SRI PRATAP COLLEGE

LIBRARY.

Class No. 891.211

Book No. R 57 V. Cp.2.

Accession No. 3892

A COMPLETE
ALPHABETICAL INDEX
OF ALL THE WORDS IN
THE RIGVEDA.

PREPARED AND PUBLISHED

BY

SWAMI VISHWESHVARANAND

AND

SWAMI NITYANAND.

Under the Kind patronage of H. H. the Maharaja Sahib Sir Sayaji Rao Sena-Khas Khel Shamsher Bahadur G. C. S. I. Gaekwad of Baroda.

Vol I.

FIRST EDITION

PRINTED AT THE "NIRNAYA-SAGARA" PRESS,

BOMBAY.

1908.

cp.2.

3892.

(Registered under the Government of India's Act XXV of 1867.)

All rights reserved by the publishers.

ॐ

ऋग्वेदपदानां

अकारादिवर्णक्रमानुक्रमणिका ।

श्रीमन्महाराजा सर सयाजीराव गायकवाड

सेनाखासखेल शमशेर बहादुर श्रीबडोदाधीशैः संरक्षकपदाङ्गीकारतयालङ्कृता ॥

श्रीमत्स्वामिविश्वेश्वरानन्द-नित्यानन्दाभ्यां

संगृह्य संस्कृता ।

सा च

मुम्बय्यां

"निर्णयसागर" मुद्रणालयेऽङ्कयित्वा प्राकाश्यं नीता ।

(प्रथमावृत्तिः ।)

प्रथमभागः

अस्याः पुनर्मुद्रणादिविषये सर्वेऽधिकारा उक्तस्वामिभ्यां स्वायत्तीकृताः.

संवत् १९६४ सन १९०८.

(अस्य ग्रन्थस्य पुनर्मुद्रणाधिकारो राजकीयनियमानुसारेण प्रकटयितृभ्यास्स्वाधिन रक्षितः)

PREFACE.

THE history of every nation of the world reveals the fact that a nation never existed without a religion, and that the revolution which turned a tribe into a nation originated from religion. Religion is not only the cause of a nation's origin, but it is also the cause of its existence, rise and fall. Whenever the highest religious ideal spread in a country, its people rose to be a mighty nation; but whenever religion was promulgated in its corrupt forms, by illiterate and selfish people, the nation declined and perished. The Hindu Aryans are such a religion-loving and religion-abiding nation that they can perform no action—social, moral, physical or spiritual—without the help of religion, from birth to death. In fact, every action of theirs is connected with some religious rite. When the Aryans are so religious that they cannot move a step in the absence of religion, their elevation can only be effected through the medium of a sound religion. It is therefore very necessary and desirable to improve and reform the present corrupt state of religion, because the improvement of the people depends upon the improvement of their religion. For centuries the Hindu religion has been so degraded and reduced to such a state that its present form cannot be called a religion. The so-called present religion of the Hindus is divided into hundreds of creeds which have degraded our national faith as a whole in the eyes of the civilised nations of the world. Unless our people get correct ideas of the original Vedic Religion, which is the true religion of their forefathers, they will never rise in the scale of nations. Since their present sects claim the origin from the Vedas and their devotees are willing to accept Vedic truths, the only way of improving their condition and of securing unity among them is to give them correct ideas of what the Vedas and the kindred religious works contain.

It is our ambition to assist the Hindu community in studying the Vedas, for we are convinced that their regeneration will begin with a critical intelligent and systematic study of their sacred scriptures. Besides Vedas are at present zealously studied by Antiquarians and philologists. To facilitate the work of research of these European and Indian Scholars we have undertaken to publish, under the distinguished patronage of His Highness the Maharaja Sahib, Sir Sayaji Rao Sena-Khas Khel, Shamsher Bahadur, G.C.S.I., Gaekwar of Baroda, a Vedic Dictionary on the following lines :—

(*a*) To arrange all the words used in the Vedas in an alphabetical order, and give their etymological and grammatical construction.

(*b*) To give the meanings attached to these words grammatically, in easy Sanscrit, and explain them with quotations wherever possible.

(*c*) To give the meanings of these words as found in Vedic literature and in books of a similar character.

(*d*) To give the meanings assigned to Vedic words by European, Indian and other scholars.

(e) To notice the interpretations given by the different sects.

(f) To state meanings according to the terminology applicable to the Vedas, and to compare the various interpretations, basing our arguments on catholic and liberal principles and on Upanishads and Brahmans.

(g) Wherever necessary, to point out the religious, social, moral and physical applications and aspects of words.

This is not an easy task, but the call to duty forces us to take it up. With the help of a competent and adequate staff of pundits, copyists, etc., we hope to finish it in about 8 years.

The first portion of the Dictionary in the form of the Index of all the words of the Vedas is now put before the public. This Index will greatly aid the Vedic Students.

As a book of constant reference it will at once give them a clue to all the places where a particular word occurs.

VISHWESHWARANANDA,
NITYANANDA.

Simla.

ॐ

प्रस्तावना.

अथेदानीं तावदृग्यजुःसामाथर्ववेदानां सुप्तिङन्ताद्यखिलपदानामकारादिवर्णक्रमपूर्वकास्तत्तत्स्थानप्रद्योतकाः सङ्केताङ्का निर्दिश्यन्ते तद्यथा—

ऋग्वेदस्य ‘अंशः’ इति पदस्याग्रे यः प्राथमिकः पूर्णविरामवान् स्थूलाङ्कोऽस्ति स हि मण्डलस्य, यश्चाल्पविरामवान् द्वितीयः सूक्ष्माङ्कोऽस्ति स च सूक्तस्य, यो हि तृतीयोऽर्द्धविरामवान् सूक्ष्माङ्कः स तु मन्त्रस्येति विज्ञेयम्। यथा ‘अंशः’ **२.** १, ४; २१, १; **५.** ४२, ५; **७.** ३२, १२. अत्र सर्वत्रायमपि नियमो बोद्धव्यो यो वै मन्त्रद्योतकोऽन्तिमोऽङ्कोस्ति स पूर्णविरामं भजते।

२. यजुषि तु केवलमङ्कद्वयमेवास्ति तदुदाहरणं तु यथा—अंशः **३४.** ५४. अत्र प्रथमोऽङ्कोऽस्त्यध्यायस्य द्वितीयोऽङ्कस्तु मंत्रस्येति।

३. एवं सामवेदाथर्ववेदयोरपि ऋग्वेदवदेव क्रमशस्त्रयोऽङ्का हि बोध्याः।

४. सामवेदपदानुक्रमणिकायां तावदस्ति ‘पू’ ‘उ’ इत्येतदक्षरद्वयविन्यासोऽङ्केभ्यः प्राक् स च पूर्वार्चिकोत्तरार्चिकभागद्वयद्योतकः। तथा पूर्वार्चिकेऽङ्कत्रयं क्रमशः प्रपाठकदशतिमन्त्राणां ज्ञापकमुत्तरार्चिके तु क्रमेण प्रपाठकसूक्तमन्त्राणां च सूचकं विज्ञेयम्। यथा ‘अंशुः’ पू. **५.** ४, ७; उ. **३.** १६, १. इति। अत्र पूर्वार्चिके पञ्चमप्रपाठकस्य चतुर्थदशतौ सप्तमो मन्त्रस्तथोत्तरार्चिके तृतीयप्रपाठकस्य षोडशे सूक्ते प्रथमो मन्त्रो बोद्धव्यः।

५. परन्तु सामवेदे केषु केषु प्रपाठकेषु ‘प्रथमार्द्ध’ ‘द्वितीयार्द्ध’ इति भेदेन प्रपाठकस्य द्वौ भागौ विद्येते तथा कतिचित्प्रपाठकेषु तु ‘प्रथमार्द्ध’ ‘द्वितीयार्द्ध’ ‘तृतीयार्द्ध’ इति भेदेन भागत्रयमस्ति। एवमस्य हि प्रपाठकस्यानावश्यकतया तज्ज्ञापकोऽङ्कोऽस्माभिर्न प्रदर्शितः। अतो निर्दिष्टं पदं तत्तत्प्रपाठकस्य प्रथमे, द्वितीये, तृतीये चार्द्धप्रपाठकेऽन्वेषणीयमिति विज्ञप्तिः।

तथाहि साम्नः केषुचिन्मुद्रितेषु पुस्तकेष्वाप्रपाठकपरिसमाप्तेरविच्छिन्नैकद्वित्र्यादिदशतिसंख्या वर्तते। परन्त्वन्येषु केषुचिन्मुद्रितपुस्तकेषु त्वर्द्धप्रपाठकपरिसमाप्तावेव दशतिसंख्यासमाप्तिं नीता हि दृश्यते। अतोऽस्माभिरप्ययमेवान्तिमः क्रमो ह्युररीकृतः।

यतः प्रपाठकान्तर्गतप्रथमार्द्धप्रपाठकस्य प्रदर्शितदशतिमंत्रे निर्दिष्टं पदं यदि नोपलभ्येत तदा द्वितीयार्द्धप्रपाठकस्य तृतीयार्द्धप्रपाठकस्य वा निर्दिष्टदशत्याः निर्दिष्टमंत्रे तत्पदमन्वेष्यमित्यप्यभ्यर्थना।

यथा—'अंशुः'—पू. ५. ४; ७. इत्यत्र 'अंशु' पदं पूर्वार्चिकस्य पञ्चमप्रपाठके प्रथमार्द्धस्य चतुर्थदशतौ नोपलभ्यते तदास्यैव प्रपाठकस्य द्वितीयार्धस्य चतुर्थ(केषुचित्पुस्तकेषु नवमीतिनिर्दिष्ट)दशतौ सप्तमे मन्त्रे ह्युपलभ्येत। एवमन्यत्राप्यूह्यम् ॥

६. अस्ति खलु साम्नो महानाम्न्यार्चिकाख्यस्तृतीयो भागस्तत्र तु केवलं दशर्चे एव साम्नः पदानुक्रमणिकावसाने पृथक्त्वेनैव तत्पदानुक्रमणिका मुद्रापिता।

७. एवं साम्नः पदानुक्रमणिकायां पदानामुपरि ये वै स्वराः किल वर्त्तन्ते ते तु कारणवशात्संहितापाठानुसारेणैव मुद्रापिता इत्यपि बोद्धव्यम् ॥

८. कचिद्यत्र तत्राङ्कयोर्मध्ये लम्बायमानैका रेखापि मुद्रितास्ति। यथाथर्ववेदे—अंहसः **४. २३, १—७;** इत्यत्रेयं लम्बायमाना रेखा प्रथममन्त्रादारभ्य सप्तममन्त्रपर्यंतमंहस इति पदमस्तीति संकेतं बोधयतीति शमित्योम् ॥

सिमला, १–६–१९०८.

ह० स्वा० विश्वेश्वरानन्दनित्यानन्दयोः.

ऋग्वेदपदसूची.

अ

अंशः २. १, ४; २७, १; ५. ४२, ५; ७. ३२, १२.
अंशं १. १०२, ४; २. १९, ५; ३. ४५, ४.
अंशवः ८. ९, १९; ५३, ४.
अंशवे १. ४६, १०.
अंशाऽइव ५. ८६, ५; १०. १०६, ९.
अंशाः १०. ३१, ३.
अंशाय १. ११२, १.
अंशुः ३. ३६, ६; ४. २२, ८; ५. ४३, ४; ९. ६२, ४; ६८, ४; ७४, २; ५; ८९, ६; ९१, ३; ९२, १; १०. १७, १२; ९४, १०.
अंशुना ४. ५८, १.
अंशुऽभिः १. ९१, १७; ९. १५, ५; ६७, २८.
अंशुं १. १३७, ३; ३. ३६, ७; ४. २६, ६; ५. ३६, १; ६. १७, ११; २०, ६; ७. ९८, १; ८. ५, २६; ७२, २; ९. ६८, ६; ७२, ६; ८६, ४६; ९५, ४; ९७, १४; १०. ९४, ९; ११३, २; १४९, ५.
अंशुऽमतीं ८. ९६, १३.
अंशुऽमत्यां ८. ९६, १५.
अंशुऽमत्याः ८. ९६, १४.
अंशोः १. १२५, ३; २. १३, १; ३. ४८, २; ४. १, १९; २५, ३; ९. ९६, ८; १०७, १२; १०. ९४, ८.
अंसत्रऽकोशं १०. १०१, ७.
अंसत्रं ८. १७, १४.
अंसत्रा ४. ३४, ९.
अंसयोः ५. ५७, ६.
अंसाभ्यां १०. १६३, २.
अंसेषु १. ६४, ४; १६६, ९; १०; १६८, ३; ५. ५४, ११; ७. ५६, १३.
अंसौ १. १५८, ५.
अंस्याः १. १९१, ७.
अंहः १. ४२, १; २. २३, ४; ५; २८, ६; ३३, २; ३४, १५; ३. १५, ३; ५९, २; ४. २, ९; ३, १४; ११, ६; १२, ६; २०, ९; ५. ३१, १३; ४५, ११; ६. २, ४; ३, १; २; ४, ८; ११, ६; ३७, ४; ४४, १६; ६७, ८; ७. ४०, ४; ६०, ६; ६६, ५; ८. १९, ६; ९. १०४, ६; १०. ३५, १४; ३९, ११; ६३, ६; १२६, १.
अंहुःऽमुचे १०. ६३, ९.
अंहुःऽयुवः ५. १५, ३.
अंहुतिः १. ९४, २; ८. ७५, ९.
अंहुतिऽभ्यः ५. ५५, १०.
अंहुतिं ८. ६७, २; २१.
अंहसः १. १८, ५; ३६, १४; ५८, ८; ९१, १५; ९३, ८; १०६, १–६; ११५, ६; ११७, ३; ११८, ८; १३६, ५[२]; १८०, ५; २. २६, ४; ३३, ३; ३. ३२, १४; ४. २, ८; ५३, ६; ५५, ५; ५. ५१, १३; ६. १६, ३०; ३१; ४८, ८; ७. १, १५; १५, ३; १३; १६, १०; ७१, ५; १०४, २३; ८. १८, ६; १०; २४, २७; ३१, २; ९. ५६, ४; १०. २४, ३; २५, ८; ३६, २; ३; ६५, १२; ६६, ५; ९७, १५; १२६, २; १३२, ७[२]; १६४, ४.
अंहसि १. ५४, १.
अंहांसि ६. २, ११; ७. २३, २.
अंहुरः १०. ५, ६.
अंहूरणा ६. ४७, २०.
अंहूरणात् १. १०५, १७.
अंहोः १. ६३, ७; १०७, १; २. २६, ४; ५. ६५, ४; ६७, ४; ८. १८, ५; ६७, ७.
अर्कः ५. ८३, १०; ७. ७७, १; ८. ७३, १६.
अकः १. २४, ८; १२३, ७; ४. १८, ५; ७. ७६, १; १०. ५३, ३[२]; ६७, ४.
अर्कनिष्ठासः ५. ५९, ६; ६०, ५.
अर्कं ८. ८०, १; १०. ४९, ६.
अकरं १. ११४, ९; १०. ४९, ५; ८५, १७; १२४, ४; १२७, ८; १६७, ४.
अकरित्यर्कः २. १२, ४.
अकरित्यर्कः १. ३३, १५; २. ३८, ८; ३. ५९, ९; ५. २९, १०; ८०, ६; ७. ८, २; १०. १६९, ४.
अर्कर्ते १. २०, ६.
अकर्त ४. ३५, ५[२].
अर्कर्म ३. १४, ७; ४. २, १९; ५. २९, १५; ६. १५, १९.
अकर्म ४. १६, २०; ८. २, ३; १०. ३९, १४; ६८, १२.
अकर्मा १०. २२, ८.
अकल्पः १. १०२, ६.
अकल्पयत् १०. १९०, ३.
अकल्पयन् १०. ९०, ११; १४.
अर्कवऽभरिं ३. ४७, ५.
अर्कवऽभरी ७. ९६, ३.
अर्कवाः ५. ५८, ५.
अर्कवाभिः १. १५८, १; ६. ३३, ४.
अर्कविषु ७. ४, ४.
अर्कवेभिः ६. ६०, ३.
अर्कवैः ३. ५४, १६.
अकानिषं ४. २४, ९.
अर्कामऽकर्शनः १. ५३, २.
अर्कारि १. २०, १; ५७, ३; ६३, ९; १८७, ६; ४. ६, ११; १६, २१; ६. ६३, ३.
अकारि १. १०४, १; १८४, ५; ३.

४, ४; ४. ३४, ३; ६. ४१, ३; ७. ६०, १२; ९७, ९.
अकारिषं ४. ३९, ६.
अकारीत् ४. ३९, ३.
अकिरत् १. ३२, १३.
अकुत्र १. १२०, ८.
अकुध्र्यक् १०. २२, १२.
अकुमारः १. १५५, ६.
अकूपारः १०. १०९, १.
अकूपारस्य ५. ३९, २.
अकृणुत १. ११०, ३; १०. ८९, ७.
अकृणुतं ६. ६९, ५.
अकृणुतं १. ११६, १०; १४; १०. ३९, ८.
अकृणुध्वं ४. ३५, ९.
अकृणोः २. १३, २; ३; ४; ८. ९१, ७; १०. १३५, ३; १३८, ६.
अकृणोः २. १३, ५; १७, ३; ४. १९, ६; २८, ४; ६. १, १; १०. ११२, ८; १८०, ३.
अकृणोत् २. १७, ६; ५. ४२, १३; ६. ४७, ४; ९. ९२, ५; १०. ३०, ७; ४३, ८; १०४, १०.
अकृणोत् १. १६४, २८; २. १७, ५; ३. ३०, १०; ३४, ३; ६. ८, ३; ४४, २३; ७. १८, ५[२]; ११; ३३, ५; १०. ६८, ६; ८८, ४.
अकृणोत ४. ३५, ३.
अकृणोतन १. ११०, ८; १६१, ७; ११.
अकृण्वत १. ३६, ५; ५२, ९; १३२, ३; ७. ४७, १; १०. ४४, ६; ४८, ६.
अकृण्वत ३. ११, ४; ७. १६, १२; १०. १३, ४; ७७, २; ९२, २.
अकृण्वन् १. ७२, १०; ४. १, १०; १३, ३.
अकृण्वन् १. ३१, ११[२]; २. ४०, १; ३. २, १०; १७, ४; ४. ३३, ७; १०. ४६, ४; ८८, १०; १२.
अकृत ५. ३४, ८.
अकृत १. १२४, ४; ५; १८१, १; ३. २६, ८; ८. ४६, २४; १०. १२७, ३.
अकृतः १. ६३, ४.
अकृतं ६. १८, १५; ८. ६६, ९.
अकृता ४. १८, २.
अकृतात् १०. ६३, ८.
अकृते १. १०४, ७.
अकृत्तऽरुक् १०. ८४, ४.
अकृथाः ५. ३०, ८.
अकृंतत् ९. १०८, ६.
अकृंतत् १०. ६७, ५.
अकृपंत ९. ८५, ११; १०. २४, ५; १२३, ४.
अकृपयत् १०. ६८, १०.
अकृपेतां ८. ७६, ११.
अकृभ्रन् ४. २, १८.
अकृपिऽवलां १०. १४६, ६.
अकेतवे १. ६, ३.
अक्तः ४. ३, १०; ६. ४, ६; ५, ६; ९. ९६, २२.
अक्तं २. ३, ४; ४. २७, ५; १०. १७७, १.
अक्तवः १०. ३, ४; ८९, १५.
अक्तवे १०. ४०, ५.
अक्ता १. ६२, ८.
अक्तुः १. १४३, ३; २. ३०, १.
अक्तुना २. १०, ३; १९, ३.
अक्तुऽभिः १. ३४, ८; ३६, १६; ४६, १४; ५०, २; ७; ९४, ५; ११२, २५; ३. १७, १; ३१, १६; ४. ५३, १; ३; ५. ४८, ३; ८४, २; ६. ६९, ३; ९. ५०, ५; १०. १४, ९; ३७, ९.
अक्तुऽभ्यः १०. ८९, ११.
अक्तुं ७. ६६, ११; १०. ६४, ३; ९२, २.
अक्तुषु ८. ९२, ३१.
अक्तून् १. ६८, १; ५. ५४, ४; ६. ४, ५; ३९, ३; ६५, १; ७. ७९, २; ८. ५, ८; १०. १, २; १२, ७.
अक्तोः ३. ७, ६; ३०, १३; ४. १०, ५; ५. ३०, १३; ६. ३, ३; ५; २४, ९; ३८, ४; ७. ११, ३; ३९, २; १०. ९२, १; १४.
अक्तौ ६. ४९, १०.
अक्रः १. १४३, ७; १८९, ७; ३. १, १२; ४. ६, ३.
अक्रत ८. ६, ३; २३, १८; १०. १, ३; ३४, ५; ७१, २.
अक्रत १. २०, ४; ६४, ५; ९२, १; ५. २१, ३; ७. १०३, ८; ८. ६५, १२; ९. २१, ७; १०. ६६, १४; ९४, ५; १४; १५५, ५.
अक्रतुः १०. ८३, ५.
अक्रतून् ७. ६, ३.
अक्रन् १. ९२, २; ४. ३३, २.
अक्रन् १. ३३, १५; ६१, १६; २. ३९, ८; ३. ३०, २०; ३५, ८; ५. ३०, १२; ५९, १; ६. २८, १; ४४, ८; १०. १४, ९; १२८, ९.
अक्रंदः १. १६३, १.
अक्रंदत् १०. ४५, ४.
अक्रंदयः १. ५४, १.
अक्रंदयन् १०. १०२, ५.
अक्रपिष्ट ७. २०, ९.
अक्रमिषं १०. ९५, २.
अक्रमीः १०. ६०, ६.
अक्रमीत् ९. ११४, १.
अक्रमीत् ४. १५, ३; ६. ५९, ६; ९. ३६, १; ४०, १; ४५, ४; ६४, २९; ६९, ४; ७४, ८; ८६, १४; १०८, २; १०. १८९, १.
अक्रमीं १०. १६६, ५.
अक्रमुः ८. ९३, १४; ९. ४१, १.
अक्रमुः ९. १०, १; २३, २; ३१, १; ३२, १; ८६, १७; १०. ९७, १०.
अक्रविऽहस्ता ५. ६२, ६.
अक्राः १०. ७७, २.
अक्रान् ९. ६४, ९; ९७, ४०.
अक्रान् २. ११, ८; ९. ६९, ३.
अक्रामत् १०. ९०, ४; १३८, ५.
अक्रि १०. १५९, ४.
अक्रीळन् १०. ७९, ६.
अक्रुक्षत् १०. १४६, ४.
अक्रौ १. १२०, २.
अक्षे ३. ५३, १९.
अक्षः १. १६४, १३; १६६, ९; ३. ५३, १७; ६. २४, ३; ८. ५, २९; १०. ८५, १२.
अक्षः १०. ३४, ४.
अक्षण्ऽवंतः १०. ७१, ७.
अक्षण्ऽवान् १. १६४, १६.
अक्षेत् १०. ११, ७.

अक्षतः ५. ७८, ९; १०. १६६, २.
अक्षन् १. ८२, २.
अक्षन् १. १९१, १२; १०. १५, १२; २७, ८.
अक्षऽनहः १०. ५३, ७.
अक्षऽभिः १. ८९, ८; १२८, ३; १३९, २[२]; २. २, ४; ९. १०२, ८; १०. २१, ७; ७९, ५; १२७, १.
अक्षे १. ३०, १४; १५; ७. ३३, ४.
अक्षरः ९. ८५, ५.
अक्षरत् १. ११२, ११; ८. ७, १; ९. ३९, ४.
अक्षरत् ९. २८, २; ६३, ३.
अक्षरन् १. ३३, ११; ८४, ४; १८८; ५; ९. ८, १; १७, २; २१, ३; २९, १; ३०, १; ३३, २; ६३, १४; १५; ७८, ३; ९८, ११; १०१, ४.
अक्षरं १. १६४, ४२; ३. ५५, १.
अक्षरा ७. १५, ९; ३६, ७.
अक्षरा ७. १, १४.
अक्षराऽइव १. ३४, ४.
अक्षराणां ३. ३१, ६.
अक्षरे १. १६४, ३९; ६. १६, ३५.
अक्षरेण १. १६४, २४; १०. १३, ३.
अक्षस्य १०. ३४, २.
अक्षाः ९. ४३, ५.
अक्षाः १०. २७, १७.
अक्षाणि ७. ५५, ६.
अक्षारिति ९. १८, १; ६६, २८; ८७, ४; ८९, १; ९७, ४५; ९८, २; ३; १०७, ९[२]; १०९, १६; १७; ११०, १०; १०. ८९, ६.
अक्षासः १०. ३४, ६; ७.
अक्षि ९. ९, ४.
अक्षिणाः ४. १८, १२.
अक्षितऽऊतयः ८. ३, १५.
अक्षितऽऊतिः १. ५, ९; ६. २४, १.
अक्षितऽऊतिं ४. १७, १६.
अक्षितं १. ९, ७; ५८, ५; ६४, ६; १३०, ५; ५. ५३, १३; ७. ६५, १; ८. ७, १६; ७२, १०; ९. २६, २; ३१, ५; ६८, ३; ७२, ६; ७८, ३; ११०, ५; १०. १०१, ६.
अक्षितऽवसुं ८. ४९, ६.
अक्षिता ३. ४०, ७; ९. ६८, ३.
अक्षिति १. ४०, ४; ८. १०३, ५; ९. ६६, ७.
अक्षिते ९. ११३, ७.
अक्षिऽपत् ६. १६, १८; १०. ११९, ६.
अक्षियंतं ४. १७, १३.
अक्षी इति १. ७२, १०; ११६, १६; ११७, १७; १२०, ६; १०. ७९, २.
अक्षी इवेत्यक्षी इव २. ३९, ५.
अक्षीभ्यां १०. १६३, १.
अक्षीयमाणं ३. २६, ९.
अक्षीयमाणा १. १५४, ४.
अक्षुः १. १८०, ५.
अक्षे ८. ४६, २७.
अक्षेणऽइव १०. ८९, ४.
अक्षेत्रऽवित् ५. ४०, ५; १०. ३२, ७.
अक्षैः १०. ३४, १३.
अक्षोदयत् ४. १९, ४.
अक्ष्णः ८. २५, ९.
अक्ष्णयाऽध्रुक् १. १२२, ९.
अक्ष्णऽयावानः ८. ७, ३५.
अखनंतः १०. १०१, ११.
अखर्वे ७. ३२, १३.
अखिदुत् ८. ७७, ३.
अखिद्रयामऽभिः १. ३८, ११.
अख्खलीकृत्य ७. १०३, ३.
अख्यः ७. १३, ३.
अख्यत् ४. १४, १; २४, ८; ५. ३०, ९.
अख्यत् १. ३५, ७; ८; ४६, १०; ११३, ४; १२३, २; ४. २, १८; १३, १; १९, ९; ५. ८१, २; ९. १०१, ७; १०. ४५, ४; १२७, १; १८९, २.
अख्यत १. १६१, १३; ९. ६१, ७.
अख्यन् १. ३५, ५; ४. १, १८.
अख्यं १. १०९, १; ८. ५५, १.
अख्यं ५. ४८, ४.
अगच्छः ८. ९८, ३; १०. १७१, २.
अगच्छः १०. ७३, ६.
अगच्छत् १. ३२, १४; ३. ३१, ७.
अगच्छत् १०. ९८, २.
अगच्छत १. ११०, २; १६१, ६.
अगच्छतं १. ११९, ८.
अगच्छतं १. ११७, १९; ५. ७८, ४; ८. ८, १०; ५७, १; १०. ३९, ७.
अगदं १०. १६, ६; ९७, २.
अगन् १. १६४, ३७; ३. ३७, १०; ९. ३२, ५; ९७, ५.
अगन् १. १२३, २; १७९, ४; ४. ३५, २; ५३, ७; ७. २०, ९; १०. १०, ७; २९, ४; ४०, १२; ८६, २२.
अगन्म १. ५०, १०; ११३, १६; ४. ५, १२; ६. १६, ३८; ७. १२, १; ८. ४८, ३; ११; ९२, १३; ९. ६७, २९; १०. ६०, १.
अगन्म ३. ३१, १४; ३३, ३; ६. ४७, २०; ८. १९, ३२; ३९, ८; ७४, ४; १०. २, ३.
अगन्महि ६. ५१, १६.
अगमत् १०. ६०, ७.
अगमं १०. १६७, ४.
अगमं १. १६१, २; १०. १३७, ४; १६६, ४.
अगव्यूति ६. ४७, २०.
अगस्त्य १. १७०, ३.
अगस्त्यः १. १७९, ६; १८०, ८; ७. ३३, १०.
अगस्त्यं ८. ५, २६.
अगस्त्यस्य १०. ६०, ६.
अगस्त्ये १. ११७, ११; १८४, ५.
अगस्महि १. २३, २३.
अगाः ८. ४८, २.
अगाः ३. २१, ४; १०. २२, ५; १६१, ५.
अगात् ३. ३०, १३; ५३, ८; १०. ७३, ५.
अगात् १. ३५, ८; ५०, १३; ७९, २; ११३, १; २; १६[२]; ११५, १; १२३, ४; १२४, ४; १२६, ३; १६२, ७; १६३, १२; १३; १६४, १७; २७; २. ३८, ३; ४; ६; ३. ८, ४; ४. १, ७; १४, ३; ५. ८०, ५; ६. ५९, ६; ७. ७५, १; ७६, २; ७८, ३; १०. १, १; ३, ३; ३३, १; ५३, १; ३; ८५, १३; ९९, ५; १०७, १; १५९, १.
अगां ५. २, ८.

अगाम १. ३१, १६.

अगाम १०. १८, ३.

अगामि ६. १६, १९.

अगायत् १०. ६७, ३.

अगासिषुः ८. १, ७.

अगिराऽओकसः १. १३५, ९.

अगुः १०. ६१, १०.

अगुः १. ८८, ४; १७४, ८; १८१, ६; ३. ८, ९; ४२, ३; ५६, २; ७. ७५, ३.

अगूहत् २. २४, ३.

अगूहन् १०. १७, २.

अगृधत् १०. ३४, ४.

अगृभीतः ८. ७९, १.

अगृभीतऽशोचिषः ५. ५४, ५.

अगृभीतऽशोचिषं ५. ५४, १२; ८. २३, १.

अगृभ्णत ३. ९, ६; ६. ८, ४; ९. ७०, ३; ८६, ३०.

अगृभ्णन् ९. ११३, ३.

अगृभ्णाः ५. ३१, ७.

अगृभ्णात् १. १६३, २.

अगृभ्रन् ५. २, ४.

अगोः ८. २, १४.

अगोतायै ३. १६, ५.

अगोपाः २. ४, ७; ७. १८, १०.

अगोपां ३. ५७, १.

अगोऽरुधाय ८. २४, २०.

अगोह्य १. १६१, १३.

अगोह्यः ८. ९८, ४.

अगोह्यं १. ११०, ३; १०. ६४, ३.

अगोह्यस्य १. १६१, ११; ४. ३३, ७.

अग्नयः १. ५०, ३; ५९, १; १२३, ६; १२७, ५; १६४, ५१; २. २८, २; ३४, १; ३. २२, ४; २६, ४; ४. ४५, ५; ५. ६, ६; ८७, ३; ६; ७; ६. ६६, २; ७. १, ४; ७२, ४; ८. ३, २०; १९, ३३; २८, २; ४३, ४; ५; १०. ३५, १; ६; १३; ४६, ७; ८८, १८.

अग्नये १. ७४, १; ७७, १; ७८, ५; ७९, १०; १२७, ४; १०^{२}; १४०, १; १४३, १; ३. २, १; ६, १; १०, ५; १३, १; ४. ५, १; ८, ५; ५. ५, १; ११; ७, १; १२, १; १६, १; २५, ७; ६. ३, २; ८, १; १०, ३; १६, २२; ४८, १; ७. ३, ७; ४, १; ५, १; ८, ६; १३, १; १४, १; १५, ४; ६२, २; ८. १९, ५; २२; २३, १५; २३; २४; ४३, ११; ४४, २७; १०३, ६; ८; १०. ८०, ७; ८५, ४१; ९१, १४; १८७, १.

अग्ना १. ५९, ३; ४. ८, ६; ५. ३७, ५; ६. १४, १; ७. ९४, ४; ८. २७, ३; ७२, १५.

अग्नायी ५. ४६, ८.

अग्नायी १. २२, १२.

अग्निः १. १, २; ५; १२, ६; २७, १२; ३६, १७^{४}; १८; ५९, २; ६; ७; ६०, ४; ६५, ४; ६९, २; ३; ७०, १; ३; ७१, ८; ७२, १; ७४, ३; ७७, २; ४; ५; ७९, ५; १२; ९३, ५; ९८, २^{२}; ९९, १; १०५, १४; १०७, ३; ११२, १७; १२४, ११; १२७, ७; १२८, १; ३; ४; ६; ७; १३६, ७; १४१, १२; १३; १४२, ११; १४३, २; ५; ६; १४५, ५; १४८, २; १५७, १; १६१, ९; १४; १६२, १५; १६९, ३; १८८, १०; ११; २. २, ८; ३, १^{२}; १०; ४, २; ७; ९, १; १०, १; २; ३; ५; ३. १, ११; १२; १८; २, २; ८; ३, १; २; ४; ६; ९; ११; ४, २; ८; १०; ५, १–१०; १०, ४; ११, १; २; ३; ५; ६; १३, ४; १४, १; १६, १; १७, १; २०, ४; २२, १; २३, १; २५, २; ३; २६, ३; ७; २७, ४; ५; १३; १४; २९, २; ७; ९; ३१, ३; ५३, ४; ५४, १; ५५, १०; ५७, १; ४. १, १०; २०; २, १; ३, १०; ५, २; ३; ४; ६, २; ४; ५; ७; ७, ७; ११; ९, ४; १२, ३^{२}; १३, १; १५, १; २; ३; २५, ३; ४; २८, ३; ५५, ४; ८^{२}; ५. १, १; २; ३; ५; ६; २, ९; ३, १०; १२; ४, २; ६, २; ३^{२}; ९, २; ११, १; ४^{२}; १३, ३; १४, ४; १५, १; १६, २; १७, ४; १८, १; २४, २; २५, ४^{३}; ५; ६^{२}; २८, १; २९, ७; ४१, ४; १०; ४४, १५^{३}; ४९, ३; ५१, १३; १४; ५८, ३; ६०, ७; ७५, ९; ७६, १; ६. १, ६; ४, २; ४; ६, २; ८, २; ९, १; १२, १; ४; १४, २^{२}; ४; ५; १५, १०; १३; १६, १९; २८^{२}; ३४; १८, १०; ४९, १; ९; ५१, १०; ५२, ६; ६३, ४; ७. १, १४; १५; १६; ४, २; ३; ४; ५; ६; ५, २; ६, ३; ५; ६; ७; ७, ३; ४; ५; ८, १; २; ४; १०, २; ११, ४; १२, २; १५, ३; ६; १०; १६, १२; ३०, ३; ३४, १४ २५; ३५, ४; ३६, १; ३९, १; ७; ४०, ३; ४२, ४; ४४, ५; ४९, ४ ५०, २; ५१, ३; ५६, २५; ६२, ३; ६७, २; ७७, १; ७८, २; ८. ७, ३६; १२, ९; १८, ९; १९, ८; ११; १९; २२; २३; २३, १३; २५, १९; २७, १; ३९, १; ४; ५; ६^{४}; ७; ८; ९; ४०, १; ४३, ६; ७; ८; २२; ४४, १२; १६; २१; ५६, ५^{२}; ५८, २; ६०, १३; ६९, ११; ७१, १३; ७५, ४; १४; १०२, ९; १०३, २; १२; ९. ५, ११; ६६, २०; ८८, ५; १०. १, १; ६; २, २; ३; ४; ५; ३, ३; ७; ५, ७; ६, २; ४; ८, १; १६, ६; १०; ११; १७, ३; १९, २; २१, ५; ३१, ९; ४५, १; ४; ८; १२; ४६, ८; ५१, ४; ५२, ४; ६१, १४; ६५, १; ६९, ७; ११; १२; ७०, ७; ७८, २; ७९, ४; ८०, १^{४}; २^{३}; ३^{४}; ४^{३}; ५; ६; ८५, ८; ३९; ४०; ४१; ८७, १; ८८, ४; ६; ९०, १३; ९५, १२; १००, ६; १०९, २; ११०, १०; ११; ११३, ८; ११५, २; ५^{४}; ७; ११८, ३; ४; १२२, १; १२४, ४; १२८, २; १५०, ४; ५; १५१, १; १५८, १; १६२, १; २; १६४, ३; १६५, २; १६९, २; १७३, ५; १७६, ४; १८७, ५.

अग्निःऽइव १०. ८४, २; १०६, ३.

अ॒ग्नि॒ऽजि॒ह्वाः **१.** ४४, १४; ८९, ७; **३.** ५४, १०; **६.** २१, ११; ५०, २; ५२, १३; **७.** ६६, १०; **१०.** ६५, ७.

अ॒ग्नित् **२.** १, २.

अ॒ग्नि॒ऽत॒पः **५.** ६१, ४.

अ॒ग्नित॒पः॒ऽभिः **१०.** ६८, ६.

अ॒ग्नि॒ऽत॒सेभिः **७.** १०४, ५.

अ॒ग्नि॒ऽद॒ग्धाः **१०.** १५, १४.

अ॒ग्नि॒ऽदू॒तः **१०.** १४, १३.

अ॒ग्नि॒धे **१०.** ४१, ३.

अ॒ग्नि॒ऽधाने **१०.** १६५, ३.

अ॒ग्निना **१.** १, ३; १२, ६; ३६, १८; १६२, ११; **५.** ४३, ७; **८.** ३५, १; ४३, १४;

अ॒ग्नि॒ऽभिः **१.** २६, १०; **३.** २४, ४; **६.** १०, २; ११, ६; १२, ६; **७.** ३, १; **८.** १८, ९; १९, ७; ६०, १; **१०.** १४१, ६.

अ॒ग्नि॒ऽम्न्यः **७.** १, ४.

अ॒ग्नि॒ऽभ्राजसः **५.** ५४, ११.

अ॒ग्निं **१.** १, १; १२, १; ७; ९; १४, ३; २३, २०; २७, १; ३५, १; ३६, १; २; ७; ११^{२}; ३८, १३; ४४, ३; ४; ८; ४५, ४; ५८, ७; ७१, ७; ७२, ४; ८४, १८; ९६, १–७; १०६, १; ११२, १; ११३, ९; ११६, ८; १२७, १; १२८, ८; १३६, ६; १३९, १; १४३, ४; ७; १४६, १; १५७, ५; १६१, ३; १६४, ४६^{२}; १७०, ४; १७४, ३; १८१, ९; १८६, ३; **२.** २, १; ३; ४, १; ३; ८, ५; १०, ४; ६; १२, ३; २४, ७; २५, १, ४१, १९; **३.** १, २; ३; ४; ११; १४; २, ३; ४; ५; १३; १४; ३, ३; ५; ९, ५; ९; १०, ६; ११, ४; १२, ३; १३, ३; ५; १७, ४; १९, १; २०, १; ५; २३, २; ३; २६, १; २; २७, २; ६; ११; १२; २९, १; ५; १५; ३१, १५; **४.** १, १९; २, १७; १९; ३, १; ६, ८; ११; ३९, २; ४; ५८, ८; **५.** १, ४; ७; २, १२; ४, ३; ६, १; १०; ९, ३; ११, २; ४^{२}; १४, १; ३; ५; ६; १७, १; २१, ४; २२, २; २५, १; ४; ९; २८, ६; ४३, ७; ६०, १; ८५, २; **६.** १, ३; ८; ७, १; ८, ४; १०, १; १४, २; १५, ४; ७; १७; १६, ४०; ४६; ४८; २१, ९; ४९, २; ५०, १; ६०, १२; **७.** १, १; २; २, ३; ३, १; ५; ६, ४; ७, १; १०, ३; ५; १६, १; ३; ३९, ५; ४१, १; ४२, ६; ४४, १; ३; ७८, ३; ८०, २; ९९, ४; **८.** ७, ३२; ११, ६; ९; १९, २; ४; १३; २३, २; ७; २०; २२; २५; ३९, १^{२}; ८; ४३, १९; २४; २५; ३१; ४४, १; ३; ७; १३; १५; २६; ४५, १; ४८, ६; ६०, २; १७; ७१, ११; १२^{५}; १३; १४^{३}; १५^{२}; ७३, ८; ७४, १; ४; ६; ८४, १; १०२, ४; ७; १०; २२^{२}; १०३, १; ३; १०; **१०.** १, ५; ६, ५; ७, ३^{३}; ५; ११, ३; ४; १६, ९; १४; २०, २; ६; ७; ८; २१, १; ३५, ३; ४५, ६; ४६, ९; ६१, ९; १६; ६३, ९; ६४, ३; ८; ६८, ९; ७०, ३; ८०, ५^{३}; ६^{२}; ७; ८८, ३; ८; ९; १०; १२; १३; १४; ९१, ६; ८; ९२, २; १०१, १; ११८, ६; १२१, ७; १२२, ४; १२६, ५; १३६, १; १४१, ३; १५०, ४^{२}; ५; १५५, ५; १५६, १.

अ॒ग्नि॒ऽअ॑ग्निं **१.** १२, २; **६.** १५, ६; **८.** ६०, १७.

अ॒ग्नि॒ऽइ॒न्धः **१.** १६२, ५.

अ॒ग्नि॒ऽरू॒पाः **१०.** ८४, १.

अ॒ग्नि॒वान्ऽइ॑व **७.** १०४, २.

अ॒ग्नि॒ऽश्रि॒यः **३.** २६, ५.

अ॒ग्नि॒ऽसु **१.** १०८, ४; **५.** ६, ६; **७.** १, २२.

अग्नि॒ऽस्वात्ताः **१०.** १५, ११.

अ॒ग्नि॒ऽहो॒तारः **१०.** ६६, ८.

अ॒ग्नीऽइ॑ति **५.** ४५, ४; **६.** ५९, ३; ६०, १.

अ॒ग्नीन् **७.** १, १४.

अ॒ग्नी॒नां **१०.** ७८, ३.

अग्नीपर्जन्यौ **६.** ५२, १६.

अग्नीषोमा **१.** ९३, २–४; ६; ७; ९; १२; **१०.** १९, १.

अ॒ग्नीषोमा **१.** ९३, ८; **१०.** ६६, ७.

अग्नीषोमौ **१.** ९३, १; ५; १०; ११.

अग्ने **१.** १, ४; ६; ९; १२, ३; ५; १०; १२; १३, ४; १४, ७; १०; ११; १५, ४; २२, ९; २६, २; २७, ४; ३६, ५; १२; ४४, १; २; ५; ७; ९; १०; ११; ४५, ६; ८; १०; ५८, ८; ७३, ४; ७५, २; ३; ४; ५; ७६, ५; ७९, ४; ६; ९४, १–१४; ९७, १; १०५, १३; १२७, ११; १४४, ७; १४७, ५; १६१, १; १८८, ३; १८९, १; २; ३; **२.** १, १५; १६; २, २; ६; १३; ७, १; ४; ५; ९, २; ४; ६; **३.** १, १६; २२; २३; २, ६; ३, ७; १०; १०, २; ७; ११, ९; १३, ६; १४, ३; ४; १५, ५; १६, ६; १९, ३; ४; २०, २; ३; २१, ३; २२, २; ३; २३, २; २४, १; २; ३; ४; ५; २५, १; ४; ५; २७, ३; १०; १५; २८, १; ३; ४; ५; ६; २९, ४; ८; १२; ५७, ५; **४.** १, ३; ४, ३; १२; ६, १; ७, २; ९, १; १०, १; ३; ४; ५; ७; ८; **५.** १, ११; ३, ७; ९; ४, ९; ७, ९; ९, ४; १०, १; १३, १; ६; १६, ५; २०, ३; २१, १; २; २२, ४; २३, १; ४; २४, १; २५, ३; २६, १; ३; ४; ६; २७, २; २८, ३; ४; ४६, २; ५१, १; ५६, १; ६०, ६; ८; **६.** १, १३; २, १; ८; ९; १०; ११; ३, १; ४, ६; ८, ५; १०, २; ५; ११, १; २; ४; १३, १; २; ३; ५; ६; १५, १४; १५; १६; १९; १६, ३; ९; १०; १६; २१; ३३; ३६; ३७; ३८; ३९; ४३; ४८, १०; ५१, ५; ६०, ३; **७.** ३, ३; ९, ५; १४, ३; १५, १३; १६, ९; १७, १; ३; ४३, ३; **८.** ११, २; ७; १९, ९;

२९^{२}; २३, ६; ११; २६; २८; ३०; ३९, ३; ४३, २; १२; १५; १६; १८; २३; २६; २७; ४४, २; ४; ५; ८; ११; १४; २२; २५; २९; ६०, १; ३; ५; ७; १६; १८; १९; २०; ७१, ५; ६; ८; ७४, ७; ७५, ११; १३; १६; ८४, ९; १०२, १६; १८; १०३, १३; **९.** ६६, १९; २१; ६७, २३; २४; २६; **१०.** १, २; १२, ६; २१, ६; ८; ७९, ५; ६; ८०, ७; ८७, ५; ७; २१; २३; ९१, ३; ९८, १२; ११८, १; ७; १२२, ६; १२८, ६; १४०, १; १४१, १; १५०, ३; १५६, ४; ५; १९१, १.

अ॒ग्ने **१.** १, ७; १२, ४; ८; १३, १; १४, १; २; ८; १९, १; २२, १०; २३, २३; २४; २६, १०; २७, ७; ३१, १–१८; ३६, ४; ६; ९; १५; १९; ४४, १३; ४५, १; २; ७; ५८, ४; ६; ९; ५९, १; ६०, ५; ६७, ३; ७१, ६; १०; ७२, ३; ७; १०; ७३, ५; ७; ८; ९; १०; ७४, ७; ८; ९; ७६, १; २; ३; ७९, ७; ८; ९; ११; ९४, १६; ९५, ९; ११; ९६, ९; ९७, ४; १२७, ९; १३९, ७; १४०, १०; ११; १२; १३; १४१, ९; १०; १४२, १; ४; १४३, ८; १४४, ६; १४७, १; २; ३; ४; १५०, १; ३; १६४, ११; १८९, ४; ५; ६; ७; **२.** १, १–१४; २, ७; ९; १०; ११; १२; ३, ३; ४, ८; ९; ५, ८; ६, १; २; ७; ९, ३; ५; ३५, १५; ३७, ६; **३.** १, १^{२}; १७; २०; २३; ४, १; ११; ६, २; ५; ७; ८; ७, १०; ९, २; ७; १०, १; ३; १३, ७; १४, ५; ६; ७; १५, २; ३; ४; १६, ३; ५; १७, २; ३; ५; १८, १; २; ३; ४; ५; १९, २; ५; २१, १; ४; २३, ४; २८, २; २९, १०; ५४, ३; २१; २२; ५५, २; ५७, ६; ६१, ६; **४.** १, १; २; ४; ५; २, २; ४; ५; ६; ९; १०; १२; १३; १४; १६; ३, ४; ५; ६^{२}; ७; ९; १२; १३; १४; १५; १६; ४, २; ४; ५; ७; १०; १५; ५, ६; १४; ६, ६; ९; १०; १०, २; ११, १–६; १२, १; २; ४; ५; ६; **५.** १, ८; ९; १०^{२}; २, ७; ८; ११; ३, १; ६; ८; ११; ४, १; ४; ५; ६; ७; ८; १०; ११; ६, ४; ७; ८; ७, १०; ८, १; २; ३; ४; ५; ६; ७; ९, १; ६; ७; १०, २; ४; ६; ११, ३; ५; ६; १२, ३; ४^{२}; ५; ६; १३, ४; ५; १६, ४; १८, ५; २०, १; २; २३, २; २६, ५; २७, १; ३; २८, २; ५; ३०, १२; १३; १५; ३४, ९; ४३, ६; १५; ४७, ७; ५१, ८; **६.** १, १; ७^{२}; ९; १०; ११; १३; २, ५; ४, १; ७; ८; ५, ४; ६; ७; ६, ३; ७, ३; ५; ८, ६; ७; ९, ७; १०, ६; ११, ६; १२, ६; १३, ४; १४, ३; १५, ८; ९; ११; १२; १६, १; ७; १२; १३; २५; २७; ३१; ४५; २७, ८; ४८, ३; ४; ७; ८; ९; ५०, ९; ५१, १३; ५२, १२; ६०, २^{२}; ३; ६६, ९; **७.** १, ३; ५; ७; ८; ९; ११; १३; १७–२५; २, १; ३, ३; ७; १०; ४, ७; ५, ३; ४; ५; ६; ८; ९^{२}; ७, २; ७; ८, ३; ५; ९, ६; १०, ४; ११, १; २; ३; ५; १२, ३; १३, २; ३; १४, २; १५, ७; १२; १६, ५; ७; १७, ६; १८, २२; ३४, ८; ३९, ४; ५; ४२, २; ५; ४३, ५; ५९, १; ९३, ७; ८; १०४, १०; १४; **८.** १, ३३; ११, १; ३; १०; १९, १५; १७; २५; २६; २८; ३०; ३३; २३, १४; २९; ३९, २; १०; ४३, ३; ९; १०; १३; १४; १७; २०; २८; ३२; ३३; ४४, १७; १८; १९; २३; २४; २८; ३०; ६०, ९; ११; १४; १६; ७१; ४; ७४, ८; ११; ७५, १; १०; ८४, ४; १०२, १; २; २०; १०३, ४; १४; **१०.** १, ७; २, १; ७; ४, १; ४; ६; ६, ६; ७; ७, १; २; ४; ७; ८, ६; ११, ५; ७; ८; ९; १५, ९; १२; १६, १; ५; ८; १३; १९, ३; २०, १०; २१, २; ४; ७; ४५, २; ३; ९; १०; ११; ४६, १०; ५१, १; ३; ५; ७; ९; ६९, ३; ४; ६; ८; १०; ७०, ११; ८५, ३८; ८७, ४; ६; ८–१४; १६; १७; १९; २०; २२; २४; २५; ८८, ५; ९१, ४; ७; ९; १५; ९८, ८; १०; ११; ११०, ३; ११५, ९; ११८, ८; १२२, २; ३; ७; ८; १२४, १; १२८, १; १४०, ४; १४२, १; २; ३; ५; ६; १५६, २; ३.

अ॒ग्नेः **१.** २४, २; ३६, २०; ४४, १२; ७२, २; ९७, ५; ११५, १; १२२, ५; १२८, ५; १४३, ३; **२.** ८, १; ६; ३८, ५; **३.** २, ९; ११, ८; १५, १; २६, ६; ३५, ९; १०; **४.** १, ७; १५, ५; ४०, १; ५५, ७; **५.** २, १०; १३, २; ५१, २; **६.** ६, ५; ६६, १०; **७.** ६, २; ८८, २; **८.** ६, ७; ४३, १; ४४, २०; ७३, ९; ७५, ७; **९.** ९६, ५; **१०.** ३, ४; ६, १; ७, ३; १६, ७; ३४, ११; ३६, १२; ५१, २; ६; ८; ६२, ५; ६; ६९, १; २; ७६, ५; ८०, २; ४; ६; १३०, ४; १८१, २.

अ॒ग्नेःऽइ॑व **२.** २५, ३; **९.** २२, २.

अ॒ग्नौ **१.** १२४, १; १६२, १९; १८९, ८; **२.** १५, ४; **३.** ३०, २; ५५, ३; ५९, ५; **४.** ३, ११; ६, ४; २५, १; ३९, ३; **५.** १, १२; **६.** ११, ५; ४०, ३; **७.** २, ४; **१०.** ६, ३; ८८, १; २; ७; १६५, ४; १७९, ३.

अ॒ग्नौऽइ॑व **२.** १६, १.

अग्मंत **१.** ११९, ३; **४.** ३४, २.

अ॒ग्म॒त **१.** २०, ५; ८०, १६; **४.** ३४, १; **७.** ७३, ४; **९.** १४, ७; **१०.** ९१, १२.

अग्मंन् **४.** २४, ३; ४१, ९; **६.** ६३, ८; **९.** ६४, १७; ६६, १२; १११, ३; **१०.** ४२, ८.

अ॒ग्म॒न् **१.** १२२, ७; **२.** ११, १६; **४.** २, १७; १६, १५; ४४, ६; **५.**

४३, १४; ६. २८, १; ३७, २; ६९, ७; ७. ७०, ७; ९. ९२, २; १०७, ९; १०. ३०, १४; १५; ६१, १०; १३.

अग्रेऽअद्धाना ६. ६९, ६.

अग्रऽजां ९. ५,९.

अग्रतः १०. ९०, ७.

अग्रेऽनीतिं २. ११, १४.

अग्रभणे १. ११६, ५.

अग्रभं १. १९१, १३.

अग्रभीत् १. १४५, २.

अग्रभीष्म ५. ३०, १२; १५; ६. ४७, २२.

अग्रे १. २८, ६; ११२, १८; ३. ५, ५; ३०, १७; ३१, ६; ३९, ३; ५५, ७; ४. ५, ८; १३, १; २७, ५; ४६, १; ४७, १; ६. ६५, २; ७. ९१, ५; १०. ८, ४; ७१, १; ७५, २; ४; ८३, ७; ८५, १९; १००, १२; १०३, ८; १०७, ५; १११, ८; १३५, ६.

अग्रेऽअग्रं १. १२३, ४.

अग्रऽयावा १०. ७०, २.

अग्रेवः ७. ९६, ४.

अग्रा १०. ८७, १०.

अग्रिमा ५. ४४, ९.

अग्रियः १. १६, ७; ८. २६, २५; ९. ७, २; ३; ६२, २५; २६; ८३, ३; ८६, १२; १०. १२०, ८.

अग्रियं १. १३, १०; ४. ३७, ४; ६. १६, ४८; ७. ९२, २; ९. ७१, ४.

अग्रिया ४. ३४, ३.

अग्रियाऽइव १०. ९५, २.

अग्रुः ५ ४४, ७.

अग्रुवः १. १४०, ८; १९१, १४; ३. २९, १३; ४. १९, ७; ९; ३०, १६; ७. २, ५; ९. १, ८; ६६, ९.

अग्रे १. ३१, ५; १२६, ४; १२७, १०; १६४, ८; २२; २. १७, ३; ३. ४८, २; ५८, ४; ४. ५, ७; ५. १, ४; ५; ८०, २[२]; ७. ८, १; ९, ३; १५, ५; ३३, १४; ४४, ४; ६८, ९; ८०, २; ८. ६, २४; ५३, ८; ५९, ६; १००, २; ९. ६९, १; ७३, ९; ८६, १२[३]; ४२; ९६, १; ९९, १; १०६, १०; १०. १, १; १८, ७; ४५, ५; ६९, १; ८५, २८; १०७, ९; ११०, ४; १२१, १; १२९, ३; ४.

अग्रेऽगः ९. ८६, ४५.

अग्रेऽपाः ४. ३४, १०.

अग्रेऽपाभिः ४. ३४,७.

अग्रेपु ८. ६, ७.

अघऽअश्वाय १. ११६, ३.

अर्घः ५. २९, ८; ८. १२, ८.

अघः १. ४२, २.

अघं १. ९७, १[२]; २–८; २. ४१, ११; ५. ३, ७; ६. ६२, ८; ७. १०४, २; ८. १८, १४; ४७, १; १०. ३५, ३.

अघऽयतः १. ९१, ८; ४. २, ६; ५. २४, २; ६. १६, ३०; ७. १५, १५; १०. ६३, १२.

अघऽयति १. १३१, ७.

अघऽयते ६. ५१, ६; ८. ७१, ७.

अघऽयुः १. १४७, ४.

अघऽयोः १. २७, ३; १२०, ७; ४. २, ९; ७. १, १३; १०. ४२, ११.

अघऽशंसः १. १२९, ६; २. ४२, ३; ४. ४, ३; ६. ७१, ३; १०. १८५, २.

अघऽशंसं ६. ८, ५; ७. १०४, २; १०. ८७, २०.

अघऽशंसस्य १. ४२, ४.

अघशंसऽहा ९. २४, ७; २८, ६; ६१, १९.

अघऽशंसाय ७. १०४, ४; ८. ६०, ८; १०. १८२, १.

अघऽशंसे ५. ३, ७.

अघस्यं १. १२३, ५; ८. ७९, ४; ८३, ५; १०. ८९, १४.

अघा ८. ४७, ५; १०. १०२, १०.

अघाः ६. ४८, १६; ५९, ८.

अघात् १. १२८, ५; १६६, ८.

अघानी ८. ४७, २.

अघानि २. २९,५; ७. ८३, ५.

अघायं १. १८९, ५; ७. १९, ७.

अघासु १०. ८५, १३.

अघुक्षत् ५. ४०, ८.

अघोरऽचक्षुः १०. ८५, ४४.

अघ्नतः ७. २०, ८.

अघ्नता ५. ५१, १५.

अघ्नते ८. २५, १२.

अघ्न्यं १. ३७, ५.

अघ्न्यस्यं १. ३०, १९.

अघ्न्या ७. ८७, ४; ८. १०२, १९.

अघ्न्या १. १६४, २७; ७. ६८, ९; १०. ६०, ११.

अघ्न्याः ८. ७५, ८; ९. १, ९.

अघ्न्याः ९. ८०, २.

अघ्न्यानां ८. ६९, २; १०. १०२, ७.

अघ्न्याभ्यः ५. ८३, ८.

अघ्न्यां ७. ६८, ८.

अघ्न्यायाः ४. १, ६; ९. ९३, ३; १०. ४६, ३.

अघ्न्यायाः १०. ८७, १६.

अघ्न्ये १. १६४, ४०.

अघ्न्यौ ३. ३३, १३.

अंकसं ४. ४०, ३.

अंकांसि ४. ४०, ४.

अंकाः १. १६२, १३.

अंकीऽइव ३. ४५, ४.

अंकुऽयंतं ६. १५, १७.

अंकुशः ८. १७, १०.

अंकुशं १०. ४४, ९; १३४, ६.

अंकुशिनः १० ३४, ७.

अंक्ते १. १२४, ८; ५. १, ३; ८. २९, १.

अंग १. १, ६; ८४, ७; ८; ९; १९; ११८, ३; १६४, ७; २. ४१, १०; ३. ३३, ११; ५. ३, ११; ६. ४४, १०; ५०, १०; ५२, ३[२]; ७२, ५; ७. २०, ९; ५६, २; ९१, १; ८. ६, २६; ७, २; २४, १२; १५; ८०, ३; ९६, १०; ९. १०८, ३; १०. ४, ४; ४२, ३; ५४, ४; ६४, १३; ७९, ४; ८६, ७; १२९, ७; १३१, २; १४६, ४[२]; १४९, ३.

अंगं १०. ८५, ३०; १०९, ५.

अंगंऽअंगं १०. ९७, १२.

अंगात्ऽअंगात् १०. १६३, ६.
अंगानि १०. १०३, १२.
अंगाराः १०. ३४, ९.
अंगिरः १. १, ६; ३१, १७; ७४, ५; ११२, १८; २. २३, १८; ४. ३, १५; ९, ७; ५. ८, ४; १०, ७; ११, ६; २१, १; ६. २, १०; १६, ११; ८. ६०, २; ७४, ११; ७५, ५; ८४, ४; १०२, १७.
अंगिरःऽतम १. ७५, २; ८. ४३, १८; २७; ४४, ८.
अंगिरःऽतमः १. ३१, २; १००, ४; १३०, ३; ९. १०७, ६; १०. ६२, ६.
अंगिरःऽतमं ८. २३, १०.
अंगिरःऽतमा ७. ७५, १; ७९, ३.
अंगिरःऽभिः १. ६२, ५; १००, ४; २. १५, ८; ४. १६, ८; ६. १८, ५; ७. ४४, ४; १०. १४, ३; ४; ५; १११, ४.
अंगिरःऽभ्यः १. ५१, ३; १३२, ४; १३९, ७; ८. १४, ८; ६३, ३; ९. ६२, ९; ८६, २३.
अंगिरसः १. ६२, २; ७१, २; ३. ५३, ७; ४. २, १५; ३, ११; ५. ११, ६; ४५, ८; ६. ६५, ५; ७. ४२, १; ५२, ३; १०. १४, ६; ६२, ५; ६७, २; ७८, ५; १०८, ८; १०; १६९, २.
अंगिरसः १०. ६२, १.
अंगिरसां १. ६२, ३; १०७, २; १२१, १; ३; १२७, २; २. २०, ५; ६. ११, ३; १०. ७०, ९.
अंगिरस्वत् १. ३१, १७; ४५, ३; ६२, १; ७८, ३; २. १७, १; ३. ३१, १९; ६. ४९, ११; ८. ४०, १२; ४३, १३.
अंगिरस्वंतौ ८. ३५, १४.
अंगिरस्वान् २. ११, २०; ६. १७, ६.
अंगिराः १. ३१, १; ८३, ४; १३९, ९; ३. ३१, ७; ५. ४५, ७; १०. ९२, १५.
अंगिरे ४. ५१, ४.
अंगेभिः १. १४१, ८; ३. ७, ४.
अंगैः १. ८९, ८; २. ३३, ९; ३. १, ५; १०. ४, ६.
अंघ्रि ९. ५, १०; १०. १५६, ३.
अंग्ध्वे १०. १००, १०.
अंग्याः १. १९१, ७.
अच ५. ८३, ८; ९. ९७, ५४.
अचक्रत ४. १८, १२.
अचक्रं १०. १३५, ३.
अचक्रया ४. २६, ४; १०. २७, १९.
अचक्रिरन् ८. ६, २०.
अचक्रे इति १. १२१, ११.
अचक्रेभिः ५. ४२, १०.
अचक्षत १०. १२३, ६.
अचक्षयत् २. २४, ३.
अचचक्षं ५. ३०, २.
अचथः ५. ७८, ६.
अचरः १०. ५४, २.
अचरत् १. १०३, ३; ३. ४८, ३; ४. ३, १०; २४, ९; १०. १०२, ८.
अचरन् ३. ५५, २.
अचरंती इति १. १८५, २.
अचरं १०. ९५, १६.
अचरमाः ५. ५८, ५.
अचष्ट २. १५, ७; ३. ५४, ६; ४. १८, ३.
अचाकशं १०. ८६, १९; १३५, २.
अचामि १०. ११९, ५.
अचारिषं १. २३, २३.
अचिकितत् ७. ८०, २.
अचिकित्वान् १. १६४, ६.
अचिकेत् १०. ५१, ३.
अचिक्रदुः ९. २२, ७.
अचिक्रदत् ४. २४, ८; ७. ३६, ३; ८. ४६, ३१; ९. २, ६; ९६, २४.
अचिक्रदत् १. ५८, २; ७. २०, ९; ९. १८, ७; २७, ४; ६७, ४; ६८, २; ७५, ३; ७७, १; ८२, १; ८६, ९; २०; १०. ९६, १०.
अचिक्रदन् ८. १००, ५.
अचित्तः ७. ८६, ७; १०४, १; ९. ९७, ५४.
अचित्तं १०. ८७, १२.
अचित्ते ७. ६१, ५.
अचित्तैं १. १५२, ५; ६. ४६, १२.
अचित्तात् ४. २, १.
अचित्तान् ३. १८, २.
अचित्तिः ७. ८६, ६.
अचित्तिऽभिः ४. १२, ४.
अचित्तिं ४. २, ११.
अचित्ती ४. ५४, ३; ७. ८९, ५.
अचित्रं ६. ४९, ११.
अचित्रे ४. ५१, ३.
अचिध्वं १. ८७, २; ५. ५५, ७; ८. ७, २; १४.
अचीकृपं १०. ११९, ११.
अचुकुधत् ५. ३४, ७.
अचुच्यवीत् ८. ७२, ८.
अचुच्यवीतन १. ३७, १२.
अचुच्यवुः १. १६६, ५; ५. ५३, ६.
अचुच्यवुः १. ४५, ८; १६८, ४; ५. ५९, ७; ८; ८. ४२, ४; ९५, २; १०. ९७, १०.
अचेत् ४. २४. ८.
अचेत् १०. १०२, २.
अचेतत् ७. ९५, २.
अचेतयत् ३. ३४, ५; ७. ८६, ७.
अचेतसः ७. १८, ८.
अचेतसं ७. ६०, ६; ७.
अचेताः १. १२०, २.
अचेतानस्य ७. ४, ७.
अचेति १. ११३, ४; १३९, ४; ७. ६७, २; ७८, ४; ८. ५६, ५; १०. ७४, ६.
अचेति १. ८८, ५; ६. २७, ४.
अचैत् ६. ४४, ७.
अचोदते ५. ४४, २.
अचोदयः १. ४२, ५.
अचोदयत् ५. ३१, ३.
अचोदसः ९. ७९, १.
अच्छ १. २,२; ६, ६; ३१, १७; ३८, १३; ४०, ३; ४१, ६; ४४, ४; ७१, ३; १०१, ८; १०४, ५; १०५, १४; १२२, ५; १२३, ४; १२९, ५; १३०, १; ५; १३२, ५; १३९, १; १४१, १२; १४२, ४; १५१, ७; १६३, १३; १६५, ४; १३; १४; १६७, २; १७३, ११; १८६, ६; १०; २. १८,

७; १९, २; ३; २४, १२; ३६, ६; ३९, १; ५; **३.** १, १; ४, ३; १४, ३; १५, ५; १९, २; २२, ३[२]; २९, ९; ३१, ६; ३३, २; ३; ५; ३५, १; ३९, १; ४२, ३; ५३, ४; ५४, ५; ५५, ३; ५७, ३; ४; ६१, ५; **४.** १, २; १०; १९; ५, १३; १४, १; १५, ७; १६, ९; २०, २; ५; २१, ४; २४, ८; २९, ४; ३४, १; ३; ३८, ५; ४४, ५; ४५, ७; **५.** १, १; ४; २४, २; २५, १; ४१, १४; ४२, १५; ४३, ८; ४५, ५; ९; ४७, ६; ५२, १४; १५; ५५, १०; ५९, ६; ७४, ३; ७६, १; ८३, १; **६.** २, ११; ६, १; १६, १२; ४४; २२, ५; ३०, ४; ३२, ४; ३७, ३; ४१, १; ४४, १५; ४७, ७; ४९, ४; ५१, ३; ६७, २; **७.** १, १८; ३, ३; ९; ५; १०, ३; १८, ४; २३, ४; २४, ३; ३४, २०; ३६, ९[२]; ५७, ७; ६७, १; ७२, ३; ९०, १; ९२, ३; ९३, ७; **८.** २, २८; ५, ३३; १६, १०; १२; २१, ६; २२, ४; २३, १०; ३३, १३; ४८, ६; ५१, ३; ६०, २; ७१, ६; १०[२]; ७५, २; ९३, २३; १०२, ७; १०३, २; ९; **९.** १, ५; ५७, १; ६४, १६; ६६, ११; १२; ६८, १; ६९, ९[२]; ८१, २; ८७, १; ९१, १; ९२, २; ९५, ३; ९६, २; ९७, ६; ८; २५; १०६, १; १०७, १२; १०८, २; ११०, ४; **१०.** १, ७; ६, ४; २६, १; ३०, १; २; ५; ६; ३२, ५; ४३, १; ४५, ९; ४७, ६; ८८, १४; ११२, ४; १४१, १; १४३, ५.

अच्छऽउक्तौ **५.** ४१, १६[२].

अच्छदयन् **१०.** १०८, १०.

अच्छान् **६.** २८, ५; **१०.** ३४, १.

अच्छात **१.** १६५, १२.

अच्छांत्सुः **१०.** ११९, ६.

अच्छायः **१०.** २७, १४.

अच्छिद्यमानया **२.** ३२, ४.

अच्छिद्रऽऊतिः **१.** १४५, ३.

अच्छिद्रऽऊध्नी **१०.** १३३, ७.

अच्छिद्रं **२.** ३, ८; **५.** ६२, ९; **६.** ४९, ७; **८.** २७, ९.

अच्छिद्रस्य **६.** ४८, १८.

अच्छिद्रा **१.** ५८, ८; १६२, १८; **२.** २५, ५; **३.** १५, ५.

अच्छिद्राः **१.** १५२, १.

अच्छिन्नऽपत्राः **१.** २२, ११.

अच्छेदि **१.** ११६, १५.

अच्छोक्तिऽभिः **१.** ६१, ३; १८४, २; **८.** १०३, १३.

अच्युंत **५.** ५४, १२.

अच्यवयत् **२.** २४, २.

अच्युतः **१.** ५२, २; **१०.** १११, ३.

अच्युतऽच्युत् **२.** १२, ९.

अच्युतऽच्युत् **६.** १८, ५.

अच्युतं **१.** ५६, ५; **२.** ३, ३; **६.** १५, १; १७, ५; **१०.** १७०, ३.

अच्युता **१.** ८५, ४; १६७, ८; **२.** २४, २; **६.** २, ९; २२, ६; ३१, २; **८.** २०, ५; **१०.** ६१, १०.

अच्युताः **१०.** ११५, ४.

अच्युतानां **८.** ९६, ४.

अच्युतानि **३.** ३०, ४.

अज **१.** १७४, २; **६.** ४९, १२.

अज **१.** २३, १३; ४२, ३; **६.** २५, ९; ४७, ३१.

अजऽअश्व **१.** १३८, ४[२]; **६.** ५५, ३.

अजऽअश्वः **६.** ५८, २; **९.** ६७, १०.

अजऽअश्वं **६.** ५५, ४.

अजः **१.** ६७, ३; १६२, २; ४; १६३, १२; **२.** ३१, ६; **३.** ४५, २; **६.** ५०, १४; **७.** ३५, १३; **८.** ४१, १०; **१०.** १६, ४; ६४, ४; ६५, १३; ६६, ११; १३४, ६.

अजकाऽवं **७.** ५०, १.

अजगन् **१.** १३०, ९; १६१, ४; १८७, ७; **३.** ९, २.

अजगन् **१.** १६१, १; **५.** ३१, १०; **७.** १८, ७.

अजगंत **१०.** १५५, ४.

अजगंतन **१०.** ८६, २२.

अजग्मिरन् **१०.** २७, १५.

अजघ्नुषी **८.** ६७, १५.

अजतं **२.** ३९, ७.

अजति **५.** ३७, ४; **६.** ६६, ७.

अजति **१.** ३३, ३; १६१, १०; **५.** ३४, ७; **८.** ४५, ३.

अजतु **६.** ५४, १०.

अजते **१.** ९५, ७.

अजथ **५.** ५४, ४.

अजध्वं **६.** ४८, ११.

अजनः **२.** १३, ७.

अजनत् **२.** २३, १७.

अजनत् **३.** ३१, १५; **१०.** ८२, १.

अजनत **४.** ५, ५.

अजनन् **२.** १३, ५.

अजनंत **८.** १०२, १७; **१०.** ७, ५.

अजनयः **१.** १३४, ४; **१०.** ५५, ४.

अजनयः **१.** ९१, २२.

अजनयत् **२.** १९, ३; २०, ७; **९.** ९७, ४१.

अजनयत् **१.** ९६, २; **२.** ३५, १३; **१०.** १३५, ५.

अजनयथाः **१०.** ५४, ३.

अजनयन् **८.** ८९, १.

अजनयन् **२.** १०, ३; **७.** ७६, ४; **१०.** ६१, ७; ८८, १३; १२२, २.

अजनयंत **१०.** ८८, ९.

अजनयंत **१.** ५९, २; १६८, ९; **४.** १, १२; **८.** १००, ११; **१०.** ८८, ८.

अजनयं **१०.** ४८, २; १८३, ३.

अजनि **२.** ५, ४; ३४, २.

अजनि **१.** ७४, ३; ८३, ५; १४४, ४; **७.** ९४, १; **८.** ६, १०.

अजनिष्ट **५.** २, ४; ३१, ३; **७.** ४, २; **१०.** ७२, ५.

अजनिष्ट **१.** ११३, १; १२३, ९; **२.** ५, १; **३.** २९, ३; ५९, ४; **५.** ११, १; ३२, ३; **७.** ७६, १; **१०.** १७, ६.

अजंति **९.** ९१, १.

अजभर्तन **१०.** ७२, ७.

अजऽमायुः **७.** १०३, ६; १०.

अजयः **१.** ३२, १२[२]; **८.** १४, १३.

अजयः **८.** ९६, १८; **१०.** ६९, ९; १६७, १.

अजयत् १०. १०२, २.

अजरक्रुत् २. ३०, ३; ४. १७, ११; ५. ३०, ५; ६. ७३, ३; १०. १०३, १.

अजर १. ५८, ४; १२७, ९^{२}; ६. २, ९; ५, ७; ८, ५; १६, ४५; ८. २३, ११; १०. ११५, ४.

अजरः १. ५८, २; १४४, ४; १४६, २; ३. २, २; २३, १; ४. ४५, ७; ५. ४, २; ७, ४; ४४, ३; ६. ४, ३; १५, ५; २२, ३; ४८, ३; ६८, ९; ७. १५, १३; १०. ५०, ५; ८७, २१.

अजरं १. १२६, २; १६४, २; १४; ३. ८, २; ३२, ७; ५. ६, ४; २७, ६; ६. ५, ७; ८, ६; १९, २; २१, १; ३८, ३; ४९, १०; १५; ७. १८, २५; ८. ६, ३५; २३, ४; २०; ९९, ७; १०. ५१, ७; ८८, १; ३; १०६, ६; १५६, ४.

अजरयू इति १. ११६, २०.

अजरा १. ११३, १३; ५. ३४, १.

अजराः १. ६४, ३; १२७, ५^{२}; १४३, ३^{२}; ३. १८, २; ७. ३, ३; १०. ९४, ११.

अजराणि १०. ९१, ७.

अजरासः ७. ५४, २; १०. ४६, ७; ८७, २०.

अजरे इति ३. ६, ४; ६. ७०, १; १०. ३१, ७.

अजरेभिः १. १६०, ४; ६. ५, ४; ६, २; ७. १०४, ५.

अजरेभ्यः १०. ९४, ७.

अजरैः २. ८, ४.

अजरौ १. ११२, ९.

अजवसः २. १५, ६.

अजस्यं १. १६४, ६; १०. ८२, ६.

अजस्र ८. ६०, ४.

अजस्रः २. ३५, ८; ३. १, २१; २६, ७; ५४, १; ७. १, १८; १०. ६, २.

अजस्रं १. १००, १४; ९. ११३, ७; १०. ४५, १; १३९, १; १८५, ३.

अजस्रया ७. १, ३.

अजस्रा १०. १२, ७.

अजस्राः ४. ५५, २.

अजस्रेण ६. १६, ४५; ४८, ३; ७. ५, ४.

अजस्रैः १. १८९, ४.

अजहात् १०. १७, २; १३८, ५.

अजहात् ४. २६, ७; २७, २.

अजहातन ८. ७, ३१.

अजहुः ८. ९६, ७.

अजाऽइव २. ३९, २.

अजाः ६. ५७, ३; १०. २६, ८.

अजागः १०. १०४, ९.

अजातऽशत्रुः ८. ९३, १५.

अजातऽशत्रुं ५. ३४, १.

अजातान् ५. १५, २.

अजाति ५. २, ५; १२.

अजानन् १. ७२, ८; १०; ३. ३१, ४; १०. ८५, १४.

अजानां १. १६३, ६.

अजां ८. ७०, १५.

अजामयः ६. २५, ३.

अजामि ५. १९, ४; १०. १०, ९; १०.

अजामिऽभिः १. १००, ११.

अजामिं १. १११, ३; १२४, ६; ४. ४, ५; ६. ४४, १७; ७. ८२, ६.

अजामीन् ६. १९, ८; १०. ६९, १२.

अजायत १. १२८, ४^{२}; ३. २९, १४; १०. १८७, ५.

अजायत १. ११, ४; ३. ३, ११; ६. ४८, २२^{२}; ८. ६, २८; ८९, ६; १०. ११, ४; ७२, २; ४; ९०, ५; ९; १२; १३^{२}; १२९, ३; १३५, ६; १९०, १^{२}; २.

अजायथाः १. १४१, ९; १०. १८०, ३.

अजायथाः १. ५, ६; ६, ३.

अजायंत १. ३१, १; ३७, २.

अजायंत १०. ७२, ३; ४; ५; ९०, १०.

अजाव १. १७९, ३.

अजावयः १०. ९०, १०.

अजासः ६. ५५, ६; ७. १८, १९.

अजिगात् १. ३३, १३.

अजिघांसत् ४. १८, १२.

अजिन्वत् १. १५६, ५; ९. ९, ४.

अजिन्वतं १. ११२, ९; १०.

अजिन्वतं १०. ६५, १२.

अजिरः ६. ६४, ३; ८. १०१, ३; १०. ९८, २.

अजिरं १. १३८, २; ३. ९, ८; ४. ४३, ६; ७. ११, २; १०. १०२, ४.

अजिरऽयुते ८. १४, १०.

अजिरऽशोचिषः ९. ६६, २५.

अजिरऽशोचिषं ८. १९, १३.

अजिरा ३. ३५, २; ५. ५६, ६.

अजिराः १. १३४, ३.

अजिरासः १. १४०, ४; ५. ४७, २; ८. ४९, ८.

अजिहत १०. ८९, १३.

अजिहीत १०. ४९, ५.

अजिहीत २. २३, १८.

अजीगः ७. ६७, १.

अजीगः १. ११३, ४; ५; ६.

अजीगरिति १. ११३, ९; ५. १, ३

अजीगरिति १. ९२, ६; १६३, ७; ३. ५८, १; ६. ४७, ३; ६५, १; ७. १०, १; ७५, १; १०. २९, १; १०६, १.

अजीजनः ५. ८३, १०; ९. ११०, ३; ४.

अजीजनत् ४. ५३, २; ७. ७९, ३; ८. ९५, ५.

अजीजनत् ९. ४२, ४; ६१, १६; ६६, २४; १०. १३४, १^{२}.

अजीजनन् ३. २९, १३; ४. ३६, ५; ७. ७८, ३; ८. ८८, ४; ९. ७१, ५; १०२, ६; १०. ८८, १०.

अजीजनन् ३. २३, ३; १०. २३, ६.

अजीतये ९. ९६, ४.

अजीतिं ९. ९७, ३०.

अजुरं ८. १, २.

अजुर्य ६. २२, ९.

अजुर्यः २. ८, २; ६. ३०, १.

अजुर्यं १. ६७, १; १४६, ४; २. १६, १; ३. ७, ४; ५३, १५; ५. ६९, १; ६. १७, १३; १०. ८८, १३.

अजुर्यमुः ५. ६, १०.

अजुर्यस्य ८. १३, २३.

अजुर्या २. ३९, ५.

अजुर्याः २. ३, ५; ३. ७, ७; ४. ५१, ६.
अजुर्यासः १०. ९४, १२.
अजुंषत् ८. ७५, १४.
अजुषत २. ३७, ४; ९. ९२, १.
अजुंषध्वं १०. ९४, १०.
अजुंषंत ९. ३३, ९.
अजुंष्टं ५. ७७, २; ७. ७५, १; ७८, ३.
अजुंष्टा २. ४०, २.
अजुंष्टात् ७. १, १३.
अजुंष्टान् ९. ७३, ८.
अजुंष्टानि १०. १६४, ३.
अजुंष्टिः ६. ३, २.
अजुंष्टौ १. ६३, ५.
अजुषन् १. ७१, १.
अजुंहवुः १०. ८८, ९.
अजुहवुः १०. ८८, ७.
अजुंऽहुत १. ५१, ५.
अजूंर्यतः ३. ४६, १; ५. ४२, ६.
अजूर्यन् १. १५२, २.
अजे ८. ४, २०.
अजेत १. १२९, ६.
अजैः ८. ४०, ११.
अजैः ९. ७२, ५.
अजेषं १०. १५९, ६.
अजैष्म ८. ४७, १८.
अजोंपाः १. ९, ४.
अजोंष्यः १. ३८, ५.
अजोंहवीत् १. ११६, १३; ११७, १५; १६; ५. ७८, ४; ८. ४२, ५.
अजोंहवुः ७. ९४, १०.
अज्ञाः १०. ३९, ६.
अज्ञातऽकेताः ५. ३, ११.
अज्ञातऽयक्ष्मात् १०. १६१, १.
अज्ञाताः ४. २३, ७; ७. ३२, २७.
अज्ञातेषु १०. २७, ४.
अज्ञायि ६. ६५, १.
अज्मं १. १५८, ३; ६. ४, ४; ८. ४६, २८; १०. १०३, ६.
अज्मन् १. ६५, ३; ११२, १७; १६६, ५; ६. ३१, २; ८. २०, ५.
अज्मंऽभिः ८. ४६, १८.
अज्मं १. १६३, १०; ३. २, १२.
अज्मंस्य ४. ५३, ४.
अज्मेषु १. ३७, ८; १०; ८७, ३; ५. ८७, ७; ८. ४३, २०.
अज्यते १. १८८, २; ११; ३. १७, १; ८. २०, ८; ५१, ९; ९. ३२, ३; ३४, ४; ७२, १; ७६, २; १०५, २; १०. ८५, २८; ११८, ३; ४.
अज्यमानः ५. ३०, १४; ९. ९७, ३५; १०. ३१, ९.
अज्यमाना १०. ३१, १०.
अज्यसे ६. २, ८; ९. ६६, ९.
अज्यसे ३. ४०, ६; ९. ७८, २; ८५, ५.
अज्येष्ठाः ५. ५९, ६.
अज्येष्ठासः ५. ६०, ५.
अज्राः ६. २४, ८.
अज्रान् ४. १, १७; १९, ७; ५. ५४, ४; ६. ६२, २; ८. १५, २; १०. ४४, ८; ५९, ३.
अज्रे ८. २७, १८.
अज्र्या १०. ६९, ६.
अंजः १. ३२, २; १९०, २.
अंजःपाऽइव १०. ९४, १३.
अंजःऽपां १०. ९२, २.
अंजत ८. ७, २५.
अंजतः २. ३, ७.
अंजते ९. ८६, ४३.
अंजते ९. १०२, ७.
अंजते १. ६४, ४; ९२, १; १५१, ८; ७. ५७, ३; ७९, २; ८. ७२, ९; ९. १०, ३; ८६; ४३^{२}; ९७, ५७.
अंजन् १. ९२, ५; २. ३, २.
अंजन् ३. ३८, ३; ७. २, ५.
अंजंति १. ९५, ६; ३. ८, १; १४, ३; ५. ३, २; ४३, ७; ६. ११, ४; ९. १०९, २०.
अंजंतु ६. ६९, ३; १०. ८५, ४७.
अंजयः १. १६६, १०; ७. ७८, १; १०. ९५, ६.
अंजसा १. १३९, ४; ६. १६, ३; ५४, १.
अंजसाऽइव १०. ७३, ७.
अंजसि १. १३२, २^{२}.
अंजसी १. १०४, ४.
अंजसीनां १०. ३२, ७.
अंजानः २. ८, ४; ३. १०, ४; ९. ५०, ५; १०३, २; १०७, २२.
अंजानाः ४. ५८, ९.
अंजि १. १२४, ८; ४. ५८, ९; ७. ५७, ३; ८. २०, ११; २९, १.
अंजिऽभिः १. ३६, १३; ३७, २; ६४, ४; ८५, ३; ८७, १; ११३, १४; २. ३४, १३; ५. ५२, १५; ५६, १; १०. ७८, ७.
अंजिऽमंतः ५. ५७, ५.
अंजिषु २. ३६, २; ५. ५३, ४.
अंजीन् १०. ७७, २.
अंजे १. ६१, ५; ६४, १.
अंज्मः ९. ४५, ३.
अण्वे ९. १०, ५; ९१, ३.
अण्वानि ९. ८६, ४७; १०७, ११.
अण्वीः ९. १, ७.
अण्वीभिः १. ३, ४.
अण्वेषु ९. १६, २.
अण्व्या ९. १४, ६; १५, १; २६, १.
अतः १. ६, ९; २२, १६; १८; २३, १२; २५, ११; ४७, ७; ५३, ३; १०१, ८; १०८, ७; ८; ९; १०; ११; १२; १४७, ५; १६५, ५; २. २४, ७; ३. ३६, ६; ४. २, १२; १६, ५; १८, १; २; २६, ५; २७, ३; ५०, ३; ५. ३०, ५; ३४, ४; ५०, ३^{२}; ६०, ६; ६२, ८; ६. ५, ३; ४०, ५; ७. १०४, ३; ८. ५, २७; ६, २९; ८, ११; ९, १०; १०, १; २०, १८; ४९, ७; ९२, १०; ९७, ४; ९. ४८, ३; ८६, १५; ९५, १; १०. १, ४; १२, ३; १४, ९; ४६, ६; ८५, २१; ९०, ३; १०८, १०; १२०, ७; १४९, २^{२}.
अतक्त १०. २८, ४.
अतंक्षत् १. ६२, १३.
अतक्षत् १०. ४८, ३.
अतंक्षत १. ८६, ३.
अतक्षत १. १६१, ७.
अतंक्षन् २. ३१, ७; ७. ७, ६.

अतक्षन् १०. ६१, ७.
अतक्षं १. १०९, १; ५. २, ११; २९, १५.
अतक्षाम १०. ३९, १४.
अतक्षिषुः १. १३०, ६[२].
अतक्ष्म ८. ६, ३३.
अतथाःऽइव १. ८२, १.
अतन् ६. ६१, ९.
अतनत् ८. ५, १; ७२, १८.
अतनोत् २. १७, ४; १०. १११, ५.
अतंद्रः १. ७२, ७; ७. १०, ५; ८. ६०, १५.
अतंद्राः ८. २, १८.
अतंद्रासः १. ९५, २; ४. ४, १२.
अतन्वत १०. ९०, ६.
अतपत् ३. ३१, १०; १० ८८, ९.
अतसऽतनूः ९. ८३, १.
अतप्यमाने इति १. १८५, ४.
अतमानं २. ३८, ३.
अतमानाः ६. ९, २.
अतरः १. ३२, १४; १०. १०४, ८.
अतरः १०. १०८, १.
अतरत् ४. २७, २; ७. १८, ६; ८. १००, ८.
अतरन् ५. ४५, ११.
अतरन् १. ३६, ८.
अतरं १०. १०८, २.
अतर्पयः ४. १९, ५.
अतर्पयत् ९. ९, ६.
अतव्यान् ५. ३३, १; ७. १००, ५.
अतष्ट १. १६३, २; ३. ५४, १२; ४. ३५, ५.
अतसं ४. ४, ४; ८. ६०, ७.
अतसस्य ३. ७, ३.
अतसा १०. ८९, ५.
अतसानि २. ४, ७.
अतसाय्यः २. १९, ४.
अतसाय्या १. ६३, ६.
अतसि १. ३०, ४.
अतसीनां ८. ३, १३.
अतसे १. १६९, ३.
अतसेषु १. ५८, २; ४; ४. ७, १०.
अतान् ६. ६७, ६.
अतापि ७. ७०, २.
अतारिम ८. १३, २१.
अतारिषुः ३. ३३, १२.
अतारिष्म १. ९२, ६; १८३, ६; १८४, ६.
अतारीत् ७. ४, ५.
अतारीत् १. ३२, ६.
अति १. ४, ३; ३२, ८; ३६, ७; १६; ४२, ७; ५५, ३; ६४, १३; ८१, ५; ९४, ७[२]; ९७, ७; ८; ९९, १[२]; १०२, ८; १०५, ६; १०९, ६; १३५, ६[२]; ७; १४१, १३; १४३, ३; १७०, ३; १७३, २; १७४, ९; १८२, ३; १८३, ४; १८९, २; २. २, १०; ७, ३; ११, २१; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; २३, १५; २५, १; २७, ७; १६; २८, १; ३४, १५; ३. ९, ३; ४[२]; १०, ७; १५, ३; २०, ४; २७, ३; ४३, २; ४५, १; ४. ८, ८; ३६, ९; ३९, १; ५. १, ९; ३, ११; ४, ९; २५, ९; ४४, ७; ४५, ११; ५२, ३; ५३, १४; ६६, ५; ७३, ८; ६. ४, ५; १०, ५; ११, ६; १२, ५; १६, २०; १८, ७; २१, २; २२, ७; ४५, ६; ५२, २; ६१, ९; ६२, २; ७. १, १४; २३, २; ३२, २७; ३३, २; ४०, ४; ८२, १; ९७, ४; ८. १, ३३; २, ३४; १३, २१; १६, ११; १८, १७; १९, १४; २२, १४; २४, २; २६, ३; ५; ३२, २१; २२; ४२, ३; ४६, १६; ५६, ३; ५८, ३; ६०, १६; ६२, २; ६५, ९; ६७, २; ६९, १४[२]; ७३, १५; ८३, ३; ९२, १४; ९७, १५; ९. २, १; ३, २; ८, ५; १४, ६; १५, ६; १७, ५; ३०, ४; ३६, २; ४१, २; ४३, ५; ४५, ४; ६०, २; ३; ६३, ४; १५; ६६, २२; २८; ६७, २०; ६९, ४; ९; ७०, ९; १०; ७२, ३; ८५, ९; ८६, ७; २६; २९; ३१; ४४[२]; ४७; ८८, ६; ९६, ६; १७; ९७, ४; ५६; १००, ९; १०६, १३; १०७, १७; १९; २०; २५; १०. ११, ७; १२, ५; १४, १०; ३१, ९; ३३, ९; ३५, १४; ४४, १; ५६, ७; ६३, ६; १३; ७५, १; ७७, २; ८५, ३२; ८६, २; ९०, १; ५; ९१, २; ९३, ६; ९६, ८; ९७, १०; १२६, १; २; ३; ४; ५[२]; ६[२]; ७; १३३, ६; १८७, १.
अतिऽअविः ९. १३, १.
अतिऽअर्वि ९. ६, ५; ४५, ५; १०६, ११.
अतिऽआर्य ८. १०१, १४.
अतिऽआयातं ५. ७५, २.
अतिऽआयाहि ३. ३५, ५.
अतिऽऊर्मिः ९. १७, ३.
अतिऽएतवै ५. ८३, १०.
अतिऽएषि ९. ९७, ३१.
अतिऽक्रमे १. १०५, १६.
अतिऽतस्थौ १०. ६०, ३.
अतित्विषंत ५. ५४, १२.
अतिथिः १. ७३, १; १२८, ४; २. २, ८; ३. २, २; ४. १, २०; ४०, ५; ५. १, ८; ९; ३, ५; ४, ५; १८, १; ६. २, ७; ४, २; ७. ८, ४; ९, ३; ४२, ४; ८. १९, ८; १०३, १२; १०. ९१, २.
अतिथिऽग्वं १. ५३, १०; ११२, १४; ४. २६, ३; ६. १८, १३; ८. ५३, २; १०. ४८, ८.
अतिथिऽग्वस्य १. ५३, ८; २. १४, ७; ६. ४७, २२.
अतिथिऽग्वाय १. ५१, ६; १३०, ७; ६. २६, ३; ७. १९, ८.
अतिथिनीः १०. ६८, ३.
अतिथिं १. ४४, ४; ५८, ६; १२७, ८; १८६, ३; २. ४, १; ३. ३, ८; २६, २; ४. २, ७; ५. ८, २; ६. ७, १; १५, १; ४; ६; १६, ४२; ७. ३, ५; ८. २३, २५; ४४, १; ७४, १; ८४, १; १०३, १०; १०. १, ५; ९२, १; १२२, १; १२४, ३.
अतिथीन् ५. ५०, ३.

अतिथे ८. ७४, ७.
अतिऽदीव्य १०. ४२, ९.
अतिऽध्वसन् ८. ५५, ५.
अतिऽनेनीयमानः ६. ४७, १६.
अतिऽपारयः ६. ४७, ७.
अतिऽपिप्रति ७. ६६, ५.
अतिऽप्रशर्धयत् ८. १३, ६.
अतिऽमतिं १. १२९, ५.
अतिऽमन्ये १. १३८, ४.
अतिऽयाजस्य ६. ५२, १.
अतिऽयाथः ५. ७७, ३.
अतिरः ४. ३०, ३.
अतिरः १. ११, ७; ४. ३०, ७; ८. ९६, १७; १०. ५४, १; १५३, ३.
अतिरत् २. १७, २; ७. ८२, ६.
अतिरत् १. ३३, १३; ३. ३४, १; ५; ६. ९, १; ८. १४, ७.
अतिरतं १. ९३, ४; ११६, १०; १५२, १.
अतिरंत ७. ७, ६; ८. ९६, १.
अतिऽरात्रे ७. १०३, ७.
अतिऽरोचते १०. १८७, २.
अतिऽरोचमानं १०. ५१, ३.
अतिऽरोहति १०. ९०, २.
अतिऽविद्धा ८. ९६, २.
अतिऽविधे ५. ६२, ९.
अतिव्रजत्ऽभिः १. ११६, ४.
अतिष्ठः १०. ८८, ५.
अतिष्ठः ५. ११, ३.
अतिष्ठत् १. १६४, ९; ८. ८, १०.
अतिष्ठत् १. ५४, १०; ११६, १७; १६३, २; २. १५, ७; ४. १८, ८; ८. ९६, १३; १०. ९०, १; १११, २.
अतिष्ठत १०. ७२, ६.
अतिष्ठन् १. ३२, ११; ४. ३३, ७; ५. ४५, १०; ८. १, ३३; १०. २७, २३; ९८, ६; १२४, ८.
अतिष्ठंत १. ११, ६.
अतिष्ठंत १०. ८९, २.
अतिष्ठंतीनां १. ३२, १०.
अतिऽसर्पति ८. १०२, २१.
अतिऽसितं १०. ७३, ९.
अतिऽस्कदः १०. १०८, २.
अतिऽस्कदे ८. ६७, १९.
अतिस्थिपः १. ५६, ५.
अतिस्थिपत् ९. ८६, ४०.
अतिऽहार्य १. १६२, २०.
अतिऽहितं १०. १८१, २.
अतीतपे ८. ७२, ४.
अतीतृषाम ४. ३४, ११.
अतीर्णे ८. ७९, ६.
अतुस्तवं ३. ५३, १२.
अतूतुजिं ७. २८, ३.
अतूर्तः १. १२६, १.
अतूर्तऽदक्षा ८. २६, १.
अतूर्तऽपंथाः ५. ४२, १; १०. ६४, ५.
अतूर्ते ८. ९९, ७.
अतूर्ते ५. २५, ५.
अतूर्तै १०. १४९, १.
अतृणत् २. २४, ४.
अतृणत् २. १५, ३; ४. १, १९; १९, ८; ८. ७७, ५.
अतृदिलासः १०. ९४, ११.
अतृतं ७. ८२, ३.
अतृंदन् ३. ३१, ५.
अतृपासः ४. ५, १४.
अतृष्णुवंतं ४. १९, ३.
अतृपिताः १०. ९४, ११.
अतृष्णऽजः १०. ९४, ११.
अतृष्यंतीः १. ७१, ३.
अत्कः ८. ४१, ७.
अत्कं १. ९५, ७; १२२, २; ४. १६, १३; १८, ५; ५. ७४, ५; ६. २९, ३; ९. ६९, ४; १०. ४९, ३; ९५, ८; ९९, ९.
अत्कान् ५. ५५, ६.
अत्के ९. १०१, १४; १०७, १३.
अत्कैः २. ३५, १४; ६. ३३, ३.
अत्त १०. १५, ११.
अत्तः १०. ७९, १.
अत्तन १०. १००, १०.
अत्तवे ३. ३५, ७; ८. ४३, २९; ७७, ८; १०. १६, १२; ७९, ६; ८५, ३४; ९२, ३.
अत्ति १. १६४, २०; ६. ४, ५; ८. १०२, २१.
अत्ति १. ६५, ४; १४३, ५; २. १३, ४; ३५, ७; ६. १५, १; ७. ४, २; १०. २७, १३; १४; ७९, २; ४; १२५, ४.
अत्तु १०. १५, ८.
अत्नत १. ८०, १६; १०. १४३, २.
अत्नत १. ३७, १०; ५. ४८, २; ८. १३, १८.
अत्ऽभिः १. ९५, ८; १२२, ६; १६१, १४; ४. ५४, ६; ६. ४९, १४; ८. ३५, ३; ९. ६५, ६; ६८, ९; ७४, ९; ९१, २; ९३, २; ९७, ४५; १०९, १७; १०. १४, ९; ६१, २६.
अत्ऽभ्यः १. ३४, ६; ८०, २; ११२, ५; २. १, १; ३८, ११; ५. ३१, ९; ७६, ४; ६. ६२, ६; ९. ५९, २; १०. ३९, ४; ६३, २; ८०, ३.
अत्यः १. ५६, १; ५८, २; ६५, ३; १४९, ३; १९०, ४; २. ४, ४; ३. २, ७; ३८, १; ५. ३०, १४; ६. २, ८; ४, ५; ७. २४, ५; ८. ५०, ५; ९. ३२, ३; ४३, ५; ६६, २३; ७६, १; ७७, ५; ८०, ३; ८१, २; ८२, २; ८५, ५; ८६, ३; २६; ४४; ९३, १; ९६, १५; २०; ९७, १८; ४५; १०. ६, २; ७६, २; ९६, १०; १४४, १.
अत्यःऽइव ९. ४३, १.
अत्यं १. ५२, १; ६४, ६; १२९, २; १३५, ५; ३. २, ३; २२, १; ५. २५, ६; ४४, ३; ७. ३, ५; ९. ८५, ७.
अत्यंऽइव १. १३०, ६; ९. ६, ५.
अत्यस्य १. १८०, २.
अत्या ४. २, ३.
अत्याः १. १६३, १०; १७७, २; १८१, २; ३. ५६, २; ५. ३१, ९; ६. ४४, १९; ९. १३, ६; ८७, ५.
अत्याःऽइव ५. ५९, ३.
अत्यान् १. १२६, ४; ३. ३४, ९.
अत्यान्ऽइव २. ३४, ३; ३. ३२, ६.
अत्याय ३. ७, ९.
अत्यासः ७. ५६, १६; ९. ४६, १; ९७, २०.

अत्यैन २. ३४, १३.

अत्यैः ६. ३२, ५.

अत्र १. ३३, १५; ४१, ४; ४८, ४; ५२, ११; १५; ६७, २; ८४, १५; ११८, ५; ११९, ७; १२३, ३; १२४, १; १३५, ८; १५१, ५; १५४, ६; १६२, ४; १६३, ५; ७; १६४, १; ६; ११; २१; ३३^{2}; १६५, ११; १३; १७३, १२; १७९, ३; १८२, ३; १८७, ७; २. १, १५; १५, ९; १८, ३; ३०, २; ३५, ६; ३. १, ६; ७; २३, १; ३८, ३; ६; ३९, ३; ५५, २; ५७, २; ४. १, १३; १९, १; २२, ७; २६, ५; ७; ३०, ७; ४१, ६; ५४, १; ३; ५. २९, ९; ३०, ७; १०; ३१; ७; १०; ४१, ६; १७; ४४, ९; ४५, ७; ६१, ११; ६३, १; ६. १७, ८; २०, ४; २४, ५; ६३, ५; ७. ४, ४; १८, ३; १२; १९; ३०, ३; ३९, ३; ४०, ६; ५७, ५; ६५, ४; ८५, २; १०३, २; ८. १५, १२; ३१, १८; ३४, ३; ४५, २६; ९. १४, ४; ७३, ९; ९७, ५२; १०. १, ३; ११, ८; १२, ४; ६; ८; १६, १३; १७, ९; १८, ९; १२; १३; २७, ६; ९; १०^{2}; ३१, ११; ४२, ४; ५१, ४; ५३, ८; ६४, १६; ७१, २; ८; ७२, ६; ७; ७३, १; ३; ९१, ९; ९२, १५; ९३, १५; १०२, ७; १११, ६; ११३, ३; ६; १३४, ७; १३५, १; १६६, ३.

अत्रं ५. ३२, ८.

अत्रयः ५. २२, ४^{2}; ३९, ५^{2}; ४०, ९.

अत्रये १. ५१, ३; ११२, ७; १६; ११८, ७; ११९, ६; १८०, ४; ७. ६८, ५; ८. ७३, ३; ७; ८; १०. ३९, ९; १४३, ३.

अत्रसन् ८. ४८, ११; १०. ९५, ८.

अत्राणि १०. ७९, २.

अत्रिः १. १३९, ९; १८३, ५; ५. ७, १०; ४०, ६; ८; ७३, ६; ७; ७४, १; ७८, ४; ८. ४२, ५.

अत्रिणः १. २१, ५; ९४, ९; ७. १०४, १; ५; ९. ८६, ४८.

अत्रिणं १. ३६, १४; २०; ८६, १०; ६. १६, २८; ५१, १४; ८. १२, १; १९, १५; ९. १०४, ६; १०५, ६; १०. ३६, ४; ११८, १.

अत्रिऽभ्यः ५. ६७, ५.

अत्रिं १. ११६, ८; ११७, ३; २. ८, ५; ५. १५, ५; ६. ५०, १०; ७. ७१, ५; ८. ५, २५; १०. ८०, ३; १४३, १; २; १५०, ५.

अत्रिऽवत् १. ४५, ३; ५. ४, ९; ७, ८; २२, १; ५१, ८; ७२, १.

अत्रीणां ८. ३६, ६; ३८, ८.

अत्रे ५. ४०, ७.

अत्रेः ५. २, ६; ८. ३६, ७.

अत्रेःऽइव ८. ३५, १९.

अत्रेः १. १२९, ८.

अत्विषंत ८. ९४, ७.

अत्विषुः १०. ५६, ४.

अत्सारिति १०. २८, ४.

अत्सि १०. २८, ३.

अथ १. ४, ३; १०, ३; १६, ७; २४, १५; २६, ९; ४७, ३; ५४, ९; ५९, २; ७५, २; ७६, ३; ८१, ८; ८७, ४; ९२, १५; ९३, ७; ९४, ९; १०२, ६; १०; १०८, १; ६; ७; ८; ९; १०; ११; १२; १०९, २; ११४, ९; ११७, १९; ११९, ९; १३६, १; २; १६३, १३; १६४, १२; २. ३, ९; ३६, ३; ३७, ५; ३८, १; ३. ३, १; ६, ६; ९, ३; १३, ३; १७, ३; ५; २८, ५; २९, १०; ३१, ७; ३२, १०; ३४, १०; ४७, २; ५३, ३; ११; ४. १८, ५; ११; २०, ९; २४, १०; ३५, ३; ४; ३६, ४; ४२, ९; ५. ३०, ९; ६. १६, १८; ४०, १; ४; ५३, ५; ५४, ७; ७. ११, ४; ९८, ५; ८. ९, १४; १०, ५; ४०, २; ४६, १५; १६; ४८, ६; ८९, २; ९६, ७; १०२, १९; ९. ४, १; ८१, २; ८६, २८; ८७, ६; १०. १, ७; १४, १०; १५, ४; ११; १६, १; २; २३, ३; २७, २२; ५१, ७; ५२, ३; ८५, १६; ३३; १०७, ३; १०८, ३; ८; १११, ६; १२७, ६; १२९, ६; १४३, ३; १४५, ३; ५; १८२, १.

अथर्यः ४. ६, ८.

अथर्यु ७. १, १.

अथर्वणः ६. १६, १४; १०. ४८, २.

अथर्वणा १०. २१, ५.

अथर्वणि ८. ९, ७.

अथर्वऽभ्यः ६. ४७, २४.

अथर्वऽवत् ६. १५, १७; १०. ८७, १२.

अथर्वा १. ८०, १६; ८३, ५; ६. १६, १३; १०. १२०, ९.

अथर्वाणः ९. ११, २; १०. १४, ६.

अथर्व्यं १. ११२, १०.

अथो इति १. २८, ६; ५०, १२; ११३, १३^{2}; १५७, ६^{2}; १६४, ४०; ४६; १९१, १; २^{3}; ३. ३७, ११; ६०, ४; ६. ७५, १५; ८. ९१, ६; ९. ३९, ५; ६०, २; १०. २७, ९; ३९, ५; ६०, ८; ८५, २; ३५; ४१; ९०, ५; ९२, ४; ९६, १३; ९७, ९; १६^{2}; १३६, ५; १३७, ४; १५९, ३; १७३, ६; १९०, ३.

अदः १. १०५, ३; १८७, ७; ६. ५६, ३; ८. १०, १; २६, १७; ९. ६५, २२; १०. ७२, ६; १२०, ३; १५५, ३; १८६, ३.

अदक्षिणासः १०. ६१, १०.

अदत् १०. ३७, ११.

अदतें १. १८९, ५.

अदत्त १. ३२, ३; १४५, ३; ५. २९, २; १०. ३१, ११.

अदत्तन १. १३९, ७.

अदत्तं १. ११६, १३; ११७, ७; ८; २४; ११८, ९; ८. ५९, ६.

अदत्रऽया ५. ४९, ३.

अददंत ७. ३३, ११.

अददाः १. ५१, १३.

अददात् १०. ८५, ९.

अददात् ५. ३०, ११; ६. ६१, १.

अददात १०. ६४, १२.

अददां ४. २६, २.

अददुः ६. ५८, ४.

अददुः ५. २९, ५; १० १७, २; १०९, ६.

अदंदूहंत १०. ८२, १.
अदंधाः ३. ३०, ७; १०. ७३, ९.
अदुधाः १. ८३, ३; १०. १३८, ६.
अदंधात् ३. ३०, १४; ९. ९७, ४१; १०. ५४, ६.
अदुधात् १. ३३, ८; ५. ८५, २; ६. ४४, २३; १०. ५६, ७.
अदंधात ७. ३३, ४.
अदुधां १०. १८३, ३.
अदुधावत् ९. ८७, ७.
अदंधुः ३. २, ९; २९, ७; ३१, १०; ४७, ३; ६. ६७,५; १०. १२, ७; ५३, ११; ६८, ११; ८८, ११; ९०, ११.
अदुधुः २. ४, २; ६. ३९, ३; ९. ११३, ३; १०. ५६, ४; ६; ७१, ३; १२५, ३.
अदन् १०. ४, ४; ७९, ६.
अदंति १. ९४, ३; १०५, ८; २. १, १३; १४; १०. २८, ११; १४६, ३.
अदंतु १०. ८७, ७; ११०, ११.
अदंब्धः १. २४, १३; ७६, २; ८९, ५; १२८, १; २. ९, ६; २७, १३; ४. ४, ३; ५. १९, ४; ६. ७, ७; ७. ३६, २; ८. ५९, ३; ७८, ६; ९. ७७, ५; ८५, ३; ९७, १९; १०७, २; १०. १२८, ६.
अदंब्धऽधीतीन् ६. ५१, ३.
अदंब्धं ४. ५०, २; ६. ५१, १; १०. ८७, २४.
अदंब्धव्रतऽप्रमतिः २. ९, १.
अदंब्धस्य ७. ६६, ६; ८. ४४, २०; १०. ७५, ९.
अदंब्धा ३. ५४, १६; १०. ७५, ७.
अदंब्धाः १. १७३, १; २. २७, ९; ३. १, ६; ४. २, १२; ७. ६०, ५; ८. १८, २; १०१, ६; ९. ९७, ५७.
अदुब्धाः २. २८, ३.
अदंब्धान् ६. ५१, ४; ९.
अदंब्धानि १. २४, १०.
अदंब्धासः १. ८९, १; २. २७, ३; ६. ६७, ५; ८. ६७, १३.
अदंब्धे इति ४. ५५, ३.
अदंब्धेभिः १. ९५, ९; १४३, ८; ६. ८, ७; ७१, ३.
अदंब्धैः ६. ४८, १०.
अदभ्रा ५. ८६, ५.
अदंभ्रं ८. ४७, ६.
अदुमयुः ६. १८, ३.
अदुयः १०. १०३, ७.
अदुरित्थदः १. १२१, १०.
अर्दर्दः ५. ३२, १.
अदुर्दः २. २४, २.
अदुर्दरित्थदर्दः १०. ६७, ७.
अदुर्दिरुः १०. १३८, १.
अदुर्द्दृतं ४. २८, ५.
अदुर्धः २. ३८, ४.
अर्दर्शि १. ४६, ११; १०४, ५; १३६, २; ८. १०३, १.
अदुर्शि १. ९२, ५; ११३, ७; १२४, ३; ४; ४. ५२, १; ५. १, २; ७. ७७, ३; ८१, १; ८. ५६, १; १०१, १३; १०. ३, १; १०७, १.
अर्दहः ७. १, ७.
अदुहुः १. ३३, ७; १०. ६९, ११.
अर्दहत् ४. २८, ३.
अदुहत् १०. ८०, ३.
अदुाः १०. १५, १२.
अदात् ८. ३. २२; १९, ३६.
अदुात् १. ३०, १६; ६. २७, ७; ४७, २२; २४; ७. १०३, १०[३]; १०. ८५, ३९; ४१; ९९, ९.
अदुानं ४. १९, ९.
अदुाभ्य १. ३१, १०; ७. १५, १५.
अदाभ्यः १. २२, १८; ३. ११, ५; ४. ५३, ४; ५. ५, २; ९. ३, २; २८, ६; ३७, ५; ५९, २; ७५, २; ८५, ६; १०३, ४; १०. ११, १; २५, ७; २६, ७.
अदाभ्यं ३. ६२, ६; ७. १०४, २०; ८. ५, १२; ६१, १२; १०१, १२; ९. २६, ४; १०. ११८, ६.
अदाभ्यस्य ८. ७, १५.
अदाभ्या १. १५५, १.
अदुाभ्या ५. ७५, ७; ८; ७. ६६, १७.
अदाभ्याः ३. २६, ४.
अदुाभ्याः २. ३४, १०.
अदाभ्यानि १०. ५४, ४.
अदाभ्यासः ९. ७०, ३.
अदाभ्येन १०. ११८, ७.
अदुामानः ६. २४, ४; ४४, १२.
अदाशत् ४. ४२, ९.
अदाशन् ७. १९, ९.
अदाशुरिः ८. ४५, १५.
अदाशुषः ७. १९, १; ९. २३, ३.
अदाशुषां १. ८१, ९.
अदाशूःऽतरस्य ८. ८१, ७.
अदाशून् १. १७४, ६.
अदिक्षि ५. ४३, ९.
अदितयः ७. ५२, १.
अदितये १. २४, १; २; १५; ४. ३, ८; ५. ८२, ६; १०. ८७, १८; ११०, ४.
अदितिः १. ४३,२; ७२,९; ८९, १०[९]; ९४, १६; ९५, ११; ९६, ९; ९८, ३; १००, १९; १०१, ११; १०२, ११; १०३, ८; १०५, १९; १०६, ७[२]; १०७, २; ३; १०८, १३; १०९, ८; ११०, ९; १११, ५; ११२, २५; ११३, २०; ११४, ११; १५३, ३; १६२, २२; १९१, ६; २. १, ११; २७, ७; ४०, ६; ३. ४, ११; ५४, १८; २०; ४. १, २०; २५, ५; ३९, ३; ५४, ६; ५. ३१, ५; ४२, २; ४४, ११; ४६, ६; ४९, ३; ५१, ११; ५९, ८; ६. ५१, ११; ६७, ४; ७५, १२; १७; ७. ९, ३; ३५, ९; ३८, ४; ४०, २; ४; ५१, २; ६०, ८; ६६, ६; ९३, ७; ८. १२, १४; १८, ६[३]; ७; २५, ३; १०; ४७, ९[२]; ४८, २; ९. ८१, ५; १०. ११, २; १२, ८; ३६, ३; ६३, ३; ६४, १३; ६५, १; ६६, ३; ४; ७२, ४; ५; ९; ९२, ११; १३२, ६.
अदितिऽत्वे ७. ५१, १.
अदितिं १. ८९, ३; १०६, १; १३६, ३; १५२, ६; ४. २, ११; २५, ३; ५५, ३; ५. ४२, १; ४६, ३; ६२, ८; ६९, ३; ६. ५०, १; ५१, ३; ४; ७. १०, ४; १८, ८; ३९,

५;८.१९,१४;१०१, १५;१०. ६३, ५; १०; ६५, ९;९२,१४;१००,१.
अदिते २. २७, १४; ८. २७, ५.
अदिते १. ९४, १५; २. २९, ३; ४. ५५, १; ५. ५१, १४; ६. ५१, ५; ७. ६०, १; ६२, ४; ८. १८, ४; ६७, १०; १४; १८; १०. ३९, ११; ६३, १७; ६४, ५.
अदितेः १. ११३, १९; १८५, ३; ४. १२, ४; ४२, ४; ७. ४१, २; ६०, ५; ८२, १०; ८७, ७; ८८, ७; ८. १८, ५; ९. २६, १; ६९, ३; ७१, ५; ७४, ३; ५; ९६, १५; १०. ५, ७; ११, १; ६३, २; ७०, ७; ७२, ४; ८; १८५, ३.
अदितेः २. २८, ३.
अदितेःऽइव १. १६६, १२.
अदित्संतं ६. ५३, ३.
अदिद्युतत् ६. ११, ४.
अदिष्ट ५. ३६, ६; ८. ९३, १५.
अदीदेः ६. ७, ४; ७. ५, ३.
अदीदेः १. १४०, १०.
अदीदेत् १. ११२, १७; १४९, ३.
अदीधयुः ७. ३३, ५.
अदीधयुः ५. ४०, ५.
अदीधरत् १० १७३, ३.
अदीधेत् १०. ९८, ७.
अदीयं ४. २७, १.
अदुःऽकृतौ ३. ३३, १३.
अदुःऽमखस्य ८. ७५, १४.
अदुःऽमंगलीः १०. ८५, ४३.
अदुग्धाःऽइव ७. ३२, २२.
अदुच्छुनः ९. ६१, १७.
अदुद्रोत् २. ३०, ३.
अदुवः ७. ४, ६.
अदुहत् १०. ६१, १९.
अदूदुपत् १०. ८६, ५.
अदूहत् २. १२, २.
अदूहत् १०. १४९, १.
अदूक्षत १. ४८, १३.
अदूक्षत ४. ५२, ५; ७. ८३, ३; ८. ५, ३; ४३, ५.
अदूपिताय ४. ३, ३.
अदूपितेभिः १. १४३, ८.
अदूसः १. ६९, २.
अदूसऽक्रतुः ८. ७९, ७.
अदूसऽक्रतुं ६. ४९, २.
अदूसं ८. ५९, ७.
अदूप्यता १. १५१, ८.
अदूश्रं १. ५०, ३; १०. ३०, १३.
अदूश्रन् १. १९१, ५; ५. ३, ११; ७. ६७, २; ७५, ६; ७६, २; ७८, १; ३.
अदूष्टऽहा १. १९१, ८; ९.
अदूष्टाः १. १९१, ५–७.
अदूष्टाः १. १९१, १; ३; ४.
अदूष्टान् १. १९१, २; ८.
अदेदिष्ट ३. ३१, २१.
अदेदिष्ट ८. ४५, २६.
अदेवः ६. १७, ८; १८, ११; २२, ११; ८. ४६, २१; ५९, २; ७०, ७; ७१, ८; १०. ३७, ३; ३८, ३.
अदेवऽत्रात् ५. ६१, ६.
अदेवं २. २२, ४; ३. ३२, ६; ९. १०४, ६; १०५, ६.
अदेवऽयंतं २. २६, १.
अदेवऽयुः ८. ९७, ३.
अदेवऽयुं ७. ९३, ५; ८. ७०, ११; ९. ६३, २४.
अदेवऽयून् १०. २७, २; ३.
अदेवऽयोः १. १५०, २.
अदेवस्य १. १७४, ८; २. १९, ७; १०. १११, ६.
अदेवाः ८. ९६, ९.
अदेवात् १०. १२४, २.
अदेवान् ३. १, १६; १०. १३८, ४.
अदेवानि ६. ४८, १०.
अदेवीः १. १७४, ८; ३. ३१, १९; ५. २, ९; १०; ६. २५, ९; ४९, १५; ७. १, १०; ९८, ५; ८. ११, ३; ६१, १६; ९६, १५.
अदेवेन २. २३, १२.
अद्धा १. ५२, १३; ३. ५४, ५; ८. १९, ९; १०१, ११; १०. १११, ७.
अद्धातयः १०. ८५, १६.
अद्धि १. १६४, ४०; १०. १५, १२; ११६, ७; ८.
अद्धि ३. ३५, ३; ५२, ७.
अद्भुत ५. १०, २; ६. १५, २; ८. २६, २१; ९. २०, ५.
अद्भुतऽएनसः ८. ६७, ७.
अद्भुतऽएनसां ५. ८७, ७.
अद्भुतः १. ९४, १२; १३; १४२, ३; २. ७, ६; २६, ४; ५. २३, २; ६. ८, ३; ८. १३, १९; ९. २४, ६; ८३, ४; ८५, ४; १०. १५२, १.
अद्भुतऽक्रतुं ८. २३, ८.
अद्भुतक्रतू इत्यद्भुतऽक्रतू ५. ७०, ४.
अद्भुतं १. १८, ६; १४२, १०; १७०, १; ८. ४३, २४; १०. १०५, ७.
अद्भुतस्य १. ७७, ३.
अद्भुतस्य १. १२०, ४.
अद्भुता १. २५, ११.
अद्भुता ५. ६६, ४.
अद्भुतान् ४. २, १२.
अद्म १. ५८, २.
अद्मऽसत् १. १२४, ४; ८. ४४, २९.
अद्मऽसदः ६. ३०, ३.
अद्मऽसदा ७. ८३, ७.
अद्मऽसद्याय ८. ४३, १९.
अद्मऽसद्वा ६. ४, ४.
अद्मि १०. ८६, १४.
अद्य १. १३, २; ६; २३, २३; २५, १९; २८, ८; ३४, १; ३; ३५, ११; ३६, २; ६; ४४, १; ३; ९; ४५, ९; ४७, ३; ४८, १५; ४९, २; ५०, ११; ५४, ५; ५८, ८; ७६, ५; ८४, १६; ९२, १४; १५; ९३, २; १००, १०; ११३, ७; १२; १३; १७; ११५, ६; १२०, ३; १२३, ३; ८; १३; १२५, ३; १३६, ४; १४२, १; ८; १५९, ५; १६१, ११; १३; १६३, १३; १६७, १०; १८०, १०; १८२, ८; १८४, १; १८८, १; २. ३, ३; १३, ८; २७, २; २९, २; ६; ३२, ५; ३७, ५; ४१, ३; २०; २१; ३. १४, ५; १७, २; १९, ४; २९, १६; ३६, ३; ५३, २१; ४. २, २; १०, १; ४; १६, २; २४, ७; २५, १; ३; ३०, २३; ३७, २; ४४, ३; ५१, ३; ४;

५. १, ११; १३, २; २२; २; ४५, ५; ४९, १; ५१, १३; ५३, १२; ५६, १; ५८, ३; ७३, १; ७४, १; ७; ७९, १; ३; ८२, ४; ७; ६. ४, १; १५, १४²; १६, २६; १८, १३; २१, ९; २४, ५; ३०, ३; ३७, १; ५०, ४; ९; ५२, १७; ५६, ४; ६; ६३, १; ६५, ३; ६८, १; ७१, ३; ६; ७. २, १; १७, ५; ३५, १५; ४०, १; ४३, ४; ४७, १; २; ५१, २; ५७, २; ५९, ३; ६०, १; ६६, ४; १२; ६९, ६; ७५, २; ७८, ५; ९३, १; १००, ५; १०४, १५; ८. १, १०; २, २०; ३, ८; ५, १८; ९,९; १३; १०, ५; १५, ६; २०, २; २२, १; ६; २६, ३; ८; २७, ५; १४; १९; २१; ३३, १५; ४७, १८; ६४, १२; ६६, ७; ७३, ५; ९३, ४; ९४, ८; १०१, ४; ९. ४४, ६; ६५, २८; ६७, २२; ८४, १; १०. १४, १२; १५, २; १८, ३; २२, १; २; ३०, २; ३; ३२, ८; ३५, १; २; ३; ५; ७; ९; १३; ३६, २; ११; ३७, ५; ३८, ४; ४०, १४; ४५, ९; ५३, ३²; ४; ५४, २; ५५, ५; ६३, ८; ८१, ७; ८७, १३; १५; ९२, ९; ९५, १४; ११०, १; ९; ११३, १०; १२७, ४; १३५, ५; १४२, ६; १६०, २; १६७, ३.

अद्यऽअद्य ८. ६१, १७.

अद्यः २. १३, ९.

अद्युः १०. ९५, १४.

अद्युतः ६. ३९, ३.

अद्यु ७. ३४, १२.

अद्यूत्ये १. ११२, २४.

अद्यौत् १. १२३, ७; १०. १११, २.

अद्यौत् १. ११३, १४; १२२, १५; १२४, २; ३. १, ८; १८; ५, २; ९; ४. ५, १५; ६. ३, ८; १२, ३; ५१, २; ९. ८५, १२; १०. ४५, ८.

अद्रयः १. १४९, १; २. १६, ५; ३. ३२, १६; ४१, २; ४. १९, ५; ५. ८७, २; ६. ४८, ५; ६३, ३; ८. ४, १३; ५३, ३; ६३, २; ७२, ११; ८८, ३; ९. ७९, ४; १०. ७६, ७; ७८, ६; ८९, ६; ९४, ८; ११; १३; १४; १००, ८; १०४, २.

अद्रयः १०. ७६, ४; ८; ९४, १.

अद्रवः १०. ७५, २.

अद्रवत् ८. १०१, ३.

अद्रवत् ९. ९३, २.

अद्रवन् १०. ९८, ६.

अद्रिः १. १६५, ४; ३. ३१, ७; ५. ४५, ७; ६. ४०, २; ७. २२, १; ३५, ३; ६८, ४; १०. ७६, २.

अद्रिऽजाः ४. ४०, ५.

अद्रिऽजूतः ३. ५८, ८.

अद्रिणा १. १६८, ६; १०. २८, ३.

अद्रिऽदुग्धः ९. ९७, ११.

अद्रिऽदुग्धाः १. ५४, ९; ४. ५०, ३.

अद्रिऽबर्हाः १०. ६३, ३.

अद्रिऽबुध्नः १०. १०८, ७.

अद्रिऽभिः १. १२१, ८; १३०, २; १३५, २; ५; १३७, १; ३²; २. ३६, १; ३. ४४, ५; ५३, १०; ४. ४५, ५; ५. ४०, १; ८६, ६; ८. १, १७; २२, ८; ३५, २; ३८, ३; ६५, ८; ८२, ५; ९. ११, ५; २४, ५; २६, ५; ३०, ५; ३२, २; ३४, ३; ३८, २; ३९, ६; ५०, ३; ५१, १; ६३, १३; ६५, ८; १५; ६६, २९; ६७, ३; ६८, ९; ७१, ३; ७५, ४; ८०, ५; ८६, २३; ३४; १०१, ३; ११; १०७, १; १०; १०९, १८.

अद्रिऽभित् ६. ७३, १.

अद्रिं १. ७, ३; ५१, ३; ६१, ७; ६२, ३; ४; ७१, २; ७३; ६; ८५, ५; ८८, ३; ३. १, १; ४. १, १४; १५; २, १५; ३, ११; १६, ८; १८, ६; २१, ६; ५. ४३, ४; ४५, १; ५२, ९; ६. १७, ५; ३२, २; ३९, २; ६२, ७; ८. ६०, १६; ९. ९७, ३९; १०. २८, ९; ४५, ६; ६८, ११; ११२, ८; ११३, ४.

अद्रिंऽमातरं ९. ८६, ३.

अद्रिऽवः १. १०, ७; ११, ५; ८०, ७; १४; १२१, १०; १२९, १०²; १३३, २; ६²; ३. ३७, ११; ४१, १; ४. ३२, ५; ५. ३५, ५; ३६, ३; ३८, ३; ३९, १; ३; ६. ४५, ९; ४६, २; ७. २०, ८; ८९, २; ८. १, ५; १३; २, ४०; ६, २२; १२, ४; १३, २६; १५, ४; २१, ७; २४, ६; ११; ३६, ६; ४५, ११; ४६, २; ११; ५०, १०; ६१, ४; ६२, ११; ६४, १; ६८, ११; ७६, ८; ८०, ४; ९२, १८; २७; ९७, ९; ९८, ८; ९. ५३, १; १०. १४७, १.

अद्रिऽसंहतं ९. ९८, ६.

अद्रिसानो इत्यद्रिऽसानो ६. ६५, ५.

अद्रिऽसुतः ९. ७२, ४.

अद्रिऽसुतासः १. १३९ ६.

अद्री इति १. १०९, ३; ७. ३९, १; ४२, १.

अद्रुहः १. ३, ९; १९, ३, १५९, २; २. १, १४; ३. ९, ४; २२, ४; ८. ४६, ४; ६७, १३; ९७, १२; ९. ९, ४; ७३, ७; १००, १; ७; १०२, ५; १०. ६६, ८.

अद्रुहः ८. १९, ३४; २७, ९; १५.

अद्रुहं ६. १५, ७; ८. ४४, १०.

अद्रुहा ३. ५६, १; ४. ५६, २; ५. ६८, ४; ७. ६६, १८.

अद्रुहा २. ४१, २१.

अद्रुहे ९. ९, २.

अद्रुह्वाणा ५. ७०, २.

अद्रेः १. ९३, ६; ११७, १६; ११८, ३; १३९, १०; ३. ३१, ६; ५. ४१, १२; ७. ६, २; २२, ४; ७९, ४; ९. ८७, ८; १०. २०, ७.

अद्रोघ ३. ३२, ९.

अद्रोघः ६. १२, ३.

अद्रोघं ८. ६०, ४.

अद्रोघं ५. ५२, १.

अद्रोघंऽवाचं ६. ५, १; २२, २.

अद्रोघेण ३. १४, ६.

अद्रौ १. ७०, २; ५. ८५, २; ९. ९६, १०.

अद्वयंतं ३. २९, ५.

अद्वयाः १. १८७, ३; ८. १८, ६.

अद्वयाविनः १. १५९, ३.
अद्वयाविनं ३. २, १५; ५. ७५, ५.
अद्वयावी ७. ५६, १८.
अद्वयुं ८. १८, १५.
अद्रिषेण्यः १. १८७, ३.
अद्रिषेण्यं १०. १२२, १.
अद्रेषः १. २४, ४; १८६, १०; ५. ८७, ८; १०. ३५, ९.
अद्रेषेऽइति ९. ६८, १०.
अधं १. १५, १०; ३८, १०; ४२, ६; ५५, ५; ५७, २; ७२, १०; ९४, ११; १०१, ९; १०२, ७; १०४, ५; ७; ११४, १०; १२०, १२; १२१, ६; १२२, ११; १२७, ६; ९; १२९, ११; १३२, ३; १३९, १; १०; १४०, १०; १४४, २; १५१, २; १५३, १; १५६, १; १६७, २; १६९, ६; १७०, ५; १८०, ७; १८६, ९; २. १३, ५; १७, ३; ४; २२, २; २८, ९; ३०, ३; ३१, २; ४; ३. ४, ९; ६, २; ३२, ११; ३८, २; ४२, ६; ५५, १; ६; ४. २, १४; १५; १६; ५, १०; १४; ६, ७; ७, २; १०, २; १६, १७; १७, ७; १०; १८, ९; १३; २२, ६; २७, १; ३; ४; ५; ३१, ६^{२}; ५. ९, ५; १६, ४; १७, ४; २९, ५; ३८, १; ४०, ६; ४६, २; ५२, ३; ११^{३}; १६; ५४, ६; ६६, २; ४; ८५, ८; ६. १, २; २, ७; ६, ४; ५; १०, ४; १२, ५; १५, ९; १६, ४; १७, ८; ९; १०; १८, १४; १९, १२; २५, ७; ३०, २; ३१, ३; ३६, १; ४६, १०; १२; ६६, ६; ८; ७. ३, २; ४, ८; १५, १४; १८, १२; २१; २०, ३; ५; २१, ६; २९, ३; ४; ३४, २; ३८, ६; ४५, ३; ५६, १; ७; २२; २४; ७४, ५; ८२, ९; ८३, ५; ८८, २; ९०, ३; ९१, ५; १०४, १५; ८. १, १६; १८^{२}; २८; ३३^{२}; १२, १९; १३, २४; ४६, २९; ३१^{२}; ३३; ६२, ९; ६९, १६; ७५, १६; ८३, ८; ९; ८४, २; ६; ९२, २९; ९३, १२; १४; ९६, १५; ९८, ७; ११; १००, २; १०१, १०; ९. ४८, ५; ६१, २; ९७, ११; ९९, २; १०२, १; २; ११०, ९; १०. १; ६; ६, ७^{२}; १०, १४; ११, ४^{२}; २२, ६; २५, १; २; ३; ३०, १०; ३३, १; ३; ५४, ६; ५९, १; ६१, २०; २१; २२; २३; २४; ८३, ७; ८५, २७; ९२, १४; ९५, १२; १४^{२}; ९७, २; १११, ९; ११३, ८; ११५, १; १३२, ३; १३३, ५.
अधः ७. १०४, ११; ८. ३३, १९; १०. ११९, ११; १२९, ५; १६६, २.
अधःऽअक्षाः ३. ३३, ९.
अधःऽपदं १०. १३३, ४.
अधःऽपदाः ८. ५, ३८.
अधःऽपदात् १०. १६६, ५.
अधंत्त २. २२, २.
अधत्त १. ९६, १; ६. ८, ३; ८. ९६, १३; १०. १०२, ८.
अधत्तं १. ९३, ५; ११६, ८; १५; १६; ११७, १७; ११८, ७^{२}; ८; १८०, ३.
अधत्थाः ५. ३२, २.
अधन्विपुः ९. २४, १; २.
अधऽप्रिया ८. ८, ४.
अधमः ७. १०४, १६.
अधमः १. ३३, ५; ९; ५१, ५; ८. ३, २०.
अधमत् ४. ५०, ४; ८. ८९, २; १०. ५५, ८; ७२, २.
अधमं १. २४, १५; ५. ३२, ७.
अधमान् ४. २८, ४.
अध्रमानि १. २५, २१.
अधयत् १. १४४, २; ३. १, १०; ५. १, ३; १०. ३२, ८.
अधंरः १. ३२, ९; ३. ५३, २१.
अधंरं २. १२, ४; १०. ९८, ५; १५२, ४; १६६, ३.
अधंरा १. ३३, १५; १०. १४५, ३.
अधराचः १०. १३१, १; १३३, २.
अधराचीनं २. १७, ५.
अधंरात् १०. ४२, ११.
अधरात् ६. १९, ९; ७. ७२, ५; १०४, १९; ८. ६१, १६; १०. २७, १५; ८७, २०; २१.
अधरात्तात् १०. ३६, १४.
अधंरान् १. १०१, ५.
अधंराभ्यः १०. १४५, ३.
अधवंत ७. १८, १५.
अधस्तात् ३. ३०, १६.
अधाक् २. १५, ४.
अधांत् ४. ३४, १.
अधात् १. १६४, ३३; २. ३८, ४; ५; ५. ४०, ८; ६. ६६, ३; ७. ८८, ४.
अधां १०. १४५, ६^{९}.
अधांयि १. ११९, २; ३. ५, ३; ८. ४८, १०; ७४, ७; १०. ३१, ३.
अधायि १. ६०, ४; १०४, ७; १६२, ७; १८३, ६; ५. ७५, ९; ७. ७, ४; २४, ५; ३४, १४; १०. २९, १.
अधांरयः १. ५१, ४; ५२, ८; २. १३, ७; ६. १७, ७; ८. १२, ३०.
अधारयः ८. ७७, ९; ९३, १३.
अधांरयत् १. ६२, ७; १३९, १०; २. १७, ५; ३. ४४, ३; ८. ४१, १०; ९६, १५; १०. ४९, १०.
अधारयत् १०. ४४, ८.
अधांरयतं ५. ६२, ३.
अधांरयन् ३. २, ७; ८. ३६, १.
अधांरयंत १. २०, ८; १०३, १.
अधाविष्ट ९. ७०, ८.
अधिं १. ६, ९; १०; १६, ६; १९, ६; २१, ६; २५, १८; २८, ९; २९, ६; ३२, ७; ३३, ३; ४; ३५, ६; ११; ३६, ११; ३९, ४; ४२, ३; ४३, ७; ४६, ३; ४७, ७; ४८, ७; ४९, १; ५१, ५; ११; ५४, ११; ५६, २; ६४, ४; ७१, १०; ७२, १०; ७३, ४; १०; ८०, ४; ६; ८२, ४; ८३, ३; ८४, १७; ८५, २^{२}; ७; १२; ८८, ३; ९२, ४; ११४, १०; १२३, ४; १२५, ५; १२६, १; १३२, १; १३९, २^{२}; ३; ४; ११; १४०, ६; ११; १४४, ५; १४६, ३; १५५, ३; १५७, ६; १६३, २; १६४, २; ३; ५; १८

२२; २३; २९; ३९; ४२; १६६, १०; १८८, ६; **२.** २, १०; ३, ७; ८, ५; १३, ७; १६, २; २७, ६; २९, ५; ३०, ३; ४०, ४; **३.** ३, ३; ५, ९; ८, ३; ७; १९, ५; २१, ५; २९, ४; ५३, १६; ५४, ९; **४.** ४, ५; ५, ७; ९; १७, १२; २०; १८, १२; २७, ४; २८, २; ३०, १२; १४; १५; ३५, ८; ३६, ७; ३८, ७; ४५, १; ५८, ११; **५.** ३, ७; ३३, ३; ३६, ३; ४४, १३; ५२, १७; ५५, ९; ५७, ६^{2}; ६०, ७; ६१, १२; ६२, ५; ६३, १; ७८, ९^{2}; ८३, ९; ८७, ४; **६.** ६, ४; ७, ६; १६, १३; २०, ९; ३४, १; ३५, २; ४; ३८, ३; ४५, ३१; ४८, ५; ५९, ८; ६३, ५; ६५, ६; ७५, ३; १२; **७.** १८, १४; २४, ५; २५, ३; २७, ३; ३३, ११; ३६, १; ६८, ६; ७६, २; ५; ८३, २; ८८, ३; १०३, ५; **८.** १, १८; २, ८; ४, १३; ७, ७; ८, ७; ९, १४; १०, १; ३; ४; १२, १७; १७, ११; १९, ३७; २०, ११; १२; २२; २६; २३, २६; २४, ७; २५, ५; ७; २८, ५; ३०, ३^{2}; ३२, ४; ३४, १३; ४१, ४; ४२, ३; ४५, ३२; ४७, ३; ११; ४८, १४; ४९, ७; ६४, ११; ६५, ११; ६७, ६; ६८, १९; ६९, ५; १५; ७२, २; ७; ७५, १५; ८३, ७; ९१, ३; ९२, २०; ९७, ५; **९.** ८, ८; १२, ३; ६; १४, १; १९, ३; ४; २५, ३; २६, १; ३; ५; २७, १; ५; २८, ३; ३१, २; ५; ३७, ४; ५७, ४; ६३, ८; २७; ६५, १६; २५; ६६, ९; २९; ७१, ९; ७२, ९; ७३, २; ५; ७५, १^{2}; २; ३; ७९, ४; ८२, ४; ८३, २; ८५, ९; १२; ८६, ३; ६; ८; २५; २७; ९१, १; २; ९२, ४; ९४, १; ९६, १३; ९७, १६; ४०; ५३; १०१, ११; १६; १०५, ४; १०७, ८; १४; **१०.** १, २; ४, ३; १०, १; १३, ३; १५, ५; २१, ३; २७, ६; ३३, ७; ४१, २; ४३, २; ४८, २; ४९, ९; ६३, १; ६४, २; १२; ६५, ११; ७१, २; ७३, ५; ७५, २; ८; ७९, २; ८२, ६; ८५, १; ४६; ९०, ५; ९३, १५; ९४, ३; ९; १४; ९६, ४; ९८, ६; १००, ४; १०४, ९; १०५, ५; ११०, ६; १२१, ६; ८; १२३, २–४; १२७, १; १२८, ४; १२९, ४; १३०, २; १३३, १; १३५, ३; १३८, ६; १५३, २; १६३, १; ३; १७३, १; ३; १९०, १; २.

अधिऽअक्षः **१०.** १२९, ७.
अधिऽअक्षं **८.** ४३, २४; **१०.** ८८, १३.
अधिऽअक्षेण **१०.** १२८, १.
अधिऽअतिष्ठत् **१.** १६३, ९; **१०.** ८१, ४.
अधिऽअर्धत्तं **१.** ११७, ८.
अधिऽअस्थाः **१.** ४९, २.
अधिऽअस्थात् **५.** ३१, १.
अधिऽआसते **१.** २५, ९.
अधिऽइतौ **२.** ४, ८.
अधिऽइथ **७.** ५६, १५.
अधिऽइमसि **१.** ८०, १५.
अधिऽइर्यति **१०.** ३२, ३.
अधिऽइव **८.** ७, १४.
अधिऽएति **९.** ५७, ३१; ३२.
अधिऽक्षितः **८.** ४०, ३; ४१, ९.
अधिऽक्षिति **१०.** ९२, १४.
अधिऽक्षियंति **१.** १५४, २; **७.** ९६, २.
अधिऽगर्त्यस्य **५.** ६२, ७.
अधिऽजज्ञे **८.** ५८, ३.
अधित **१.** १४४, ५; **९.** ७१, ९; **१०.** १२७, १.
अधिऽतिष्ठथः **८.** १०, ६.
अधिऽतिष्ठन् **८.** ३५, ४.
अधिथाः **४.** १७, ६; ७; **६.** ३१, १.
अधिऽनिर्निजः **८.** ४१, १०.
अधिऽनीयमानः **१०.** ८९, ६.
अधिऽपत्यं **१०.** १२४, ५.
अधिऽपाः **७.** ८८, २; **१०.** ८४, ५.
अधिऽभोजना **६.** ४७, २३.
अधिऽमंथनं **३.** २९, १.
अधिऽरथं **१०.** ९८, ४; १०२, २.
अधिऽरथा **१०.** ९८, १०.
अधिऽरथानि **१०.** ९८, ९.
अधिऽराजं **१०.** १२८, ९.
अधिऽरुक्मा **८.** ४६, ३३.
अधिऽवक्ता **१.** १००, १९; १०२, ११; **८.** ९६, २०.
अधिऽवक्तारं **२.** २३, ८.
अधिऽवस्त्रा **८.** २६, १३.
अधिऽवाकाय **८.** १६, ५.
अधिऽविकर्तनं **१०.** ८५, ३५.
अधिऽसवन्यां **१.** २८, २.
अधिऽस्कन् **१०.** ६१, ७.
अधिऽस्थानं **१०.** ८१, २.
अधीतां **१०.** ४, ६.
अधीमहि **४.** ३२, १९.
अधीरा **१.** १७९, ४.
अधीवासं **१.** १४०, ९; १६२, १६; **१०.** ५, ४.
अधुः **४.** १३, ४.
अधुक्षत् **८.** ७२, १६.
अधुक्षत् **१.** ३३, १०; **१०.** १४९, १.
अधुक्षत **९.** २, ३.
अधुक्षत **९.** ११०, ८.
अधुक्षन् **२.** ३६, १; **८.** ३८, ३; ६५, ८.
अधूनुत **८.** ५२, १०.
अधूनुतं **३.** १२, ६.
अधूनुथाः **८.** १४, १४.
अधूनोत् **१.** ५९, ६.
अधूर्षत **५.** १२, ५.
अधूपत **१.** ८२, २.
अधृष्टः **१०.** १०८, ६.
अधृष्टं **६.** ६७, ८; **८.** ६१, ३; ७०, ३.
अधृष्टाः **६.** ५०, ४; १५; ६६, १०; **७.** ३, ८; **८.** ६६, १०; **१०.** १००, १२; १०१, ८.
अधृष्टासः **५.** ८७, २.
अधेनुं **१.** ११७, २०.
अधेन्वा **१०.** ७१, ५.
अधोक् **४.** १९, ७.
अध्रजन् **१.** १६६, ४.
अध्रिऽगवे **१.** ६१, १.
अध्रिऽगावः **१.** ६४, ३; **८.** २२, ११.
अध्रिऽगुः **६.** ४५, २०; **८.** ७०, १; ९३, ११.

अध्रिऽगुं १. ११२, २०; ८. १२, २; २२, १०; ६०, १७.

अध्रिगू इत्यध्रिऽगू ५. ७३, २; ८. २२, ११.

अध्रिगो इत्यध्रिऽगो ३. २१, ४; ५. १०, १; ९. ९८, ५.

अध्रिजः ५. ७, १०.

अध्रुक् ६. ५१, ५.

अध्रुक् ६. ५, १; ११, २; ६२, ४.

अध्वगोऽइव ८. ३५, ८.

अध्वन् १. ३७, १३; ६. १२, ३; २९, २, ५१, १५; ८. ८३, ६; १०. ३७, १०.

अध्वनः १. ४२, १; ७१, ९; ७२, ७; १०४, २; १४६, ३; ३. ३०, १२; ४. ५, १२; १६, २; ५. ५३, ७; ५४, १०; ६. १६, ३; ७. ६०, ४; ८. २७, १७; ५९, २; १०. २२, ४; ११५, ३; १७९, २.

अध्वनयत् ६. १८, १०.

अध्वनि ६. ४६, १३; ५०, ५.

अध्वनीत् ८. ६, १३.

अध्वने १. ४२, ८.

अध्वऽभिः १. २३, १६; ९. ५२, २.

अध्वरः ८. १९, १९; २७, ३; ९. ७, ३.

अध्वरं १. १, ४; १४, ११; १८, ८; १९, १; २३, १७; २६, १; ४४, १३; ७४, १; ४; ९३, १२; १०१, ८; १३५, ३; ७²; १५१, ३; ७; २. २, ५; ३. १७, ५; २०, १; २४, २; २८, ५; ५४, १२; ४. २, १०; ९, ६; ७; १५, २; ३७, १; ५. ४, ८; ५१, २; ७१, १; ६. ५२, १२; ६८, १०; ७. २, ७; ४२, ५; ५६, १२; ८२, ७; ८. ३५, ६; ४३, २०; ६३, ६; ७२, ९; ९. ४४, ४; ८३, ५; १०. ३०, ११; ६३, ६; ८५, १८; ९२, १५; ९४, १०; ११०, २.

अध्वरऽश्रियः १. ४७, ८; १०. ७८, ७.

अध्वरऽश्रियं १. ४४, ३; १०. ३६, ८.

अध्वरस्य १. १२८, ४; ३. ८, ८; ११, १; २३, १; ६०, ७; ४. ३, १; ७, ८; ५. ४९, ४; ७. ७, १; ११, १; ४; १६, १२; ४२, १; ८. १०, ४; १०. १, ५; ७, ५; ६६, १; १०४, ६; १४०, ५.

अध्वरस्य ४. ६, १; ६. १५, १४; ७. १४, २.

अध्वरस्यऽइव ६. ६६, १०.

अध्वराऽइव ३. ६, १०.

अध्वराणां १. १, ८; २७, १; ४४, २; ९; ४५, ४; ३. ३, ८; १०, ४; ४. ७, ३; ६. ७, २; ८. ८, १८; ११, २; ४४, ७; १०२, ७; १०. २, ६; ४६, ४; ६६, ८.

अध्वरान् १. ४८, ११; १३५, ५; ८. ३५, २१; १०. २, ३; ३२, २; ७६, ३.

अध्वराय ३. २, ७; ४. ७, ७; ७. २, ३; ४१, ६; ४३, २; ८२, १; ८. १९, २; १०.

अध्वरिऽयतां १. २३, १६; ४. ९, ५.

अध्वरिऽयसि १०. ९१, ११.

अध्वरिऽयसि २. १, २.

अध्वरे १. १२, ७; १५, ७; १६, ३; ४७, २; ५७, ३; ९४, १३; १२१, १; ७; १४२, १३; १६५, २; ३. ४, ४; ८, १; १०, १; ७; १४, ७; १६, ६; २७, ४; १२; २८, ३; ५३, १०; ५७, ४; ४. ९, ४; १५, १; ५५, १; ५. २६, ३; २८, ६; ४४, ५; ६. २, ३; १०, १; १५, ७; १६, २; ४६; ५०, ९; ७. ३, १; ७, ४; १६, ५; ३९, ४; ८४, १; १०४, १८; ८. ३, ५; ७, ६; १२, ३१–३३; १३, ३०; २७, १; ३५, २३; ४६, १८; ५०, ५; १०; ६०, २; ६६, १; ७१, १२; ९३, २३; ९. ६७, १; ७२, ५; ८२, ३; ९८, ३; १०२, ६; ८; १०. ८, ३; ११, ४; १७, ७; २१, ६; ३०, १५; ४०, १०; ७७, ८; ९४, १४; १२२, ७.

अध्वरेषु १. ५८, ७; ७७, २; १६२, १७; २. १, १३; ३. २७, ८; २९, ७; ५३, १; ६२, ५; ४. ७, १; ५१, २; ५. १, ७; ४, १; १४, २; २२, १; २८, ४; ६. ४९, २; ६३, ४; ७. १, १६; १०, ५; ९२, २; ८. ११, १०; ६०, ३; १०. ३०, ४; ८; ७६, ३; ९८, ९; ११४, ५.

अध्वरेऽस्थाः १०. ७७, ७.

अध्वर्यता १. १८१, १.

अध्वर्यवः २. १४, १–११; ३७, १; ५. ४३, ३; ७. २, ४; ९८, १; १०. ३०, २; ३; १४; १५.

अध्वर्यवः १. १५३, १; ३. ४६, ५; ५. ३१, १२; ७. ९२, २; १०३, ८; ९. ९७, ३७; १०. ३०, ६.

अध्वर्यवः ८. ४, १३.

अध्वर्युः १. ९४, ६; १६२, ५; २. ५, ६; ३. ५, ४; ४. ६, ४; ५. ३७, २; ६. ४१, २; ८. ७२, १; १०१, १०.

अध्वर्युऽभिः १. १३५, ३; ६; २. ३७, २; ३. ७, ७; ४. २७, ५; ७. ९०, १; ९. १०, ९; १०. ३०, १३.

अध्वर्युं १०. ४१, ३.

अध्वर्यू इति २. १६, ५.

अध्वर्यो इति ६. ४२, ४; ४४, १३; ८. ४, ११; ३२, २४; ९. ५१, १.

अध्वर्यो इति ३. ५३, ३; ८. २४, १६; १०. ३०, ५.

अध्वर्योः ३. ३५, १०; १०. १७, १२.

अध्वऽसु १०. १८५, २.

अध्वस्मऽभिः २. ३४, ५; ३५, १४; ९. ९१, ३.

अध्वस्मानः १. १३९, ४.

अध्वा १. ११३, ३; १७३, ११; २. १३, २; ७. ४२, २; ५८, ३; ८. ३१, ११; १०. ६१, २६; १०८, १.

अध्वानं १. ३१, १६; १०. ५१, ६; ११७, ७.

अनः २. १५, ६; ४. ३०, ११; १०. ५९, १०; ७३, ६; ८५, १०; १२; ८६, १८; १३८, ५.

अनक् २. १५, ७.

अनक्तन १०. ७६, १.

अनक्ति १. १५३, २.

अनक्ति ४. ६, ३; १०. ६८, २.

अनक्तु २. ३, २; ७. ४३, ३; ४४, ५; ८. ३९, १; ६०, १; १०. ८५, ४३.
अनक्षन् १०. ११५, ८.
अनक्षा १०. २७, ११.
अनक्षासः ९. ७३, ६.
अनग्नाः ३. १, ६.
अनग्निऽत्राः १. १८९, ३.
अनग्निऽदग्धाः १०. १५, १४.
अनज ५. ५४, १.
अनजन् ३. १९, ५.
अनज्यात् १०. ३१, ४.
अनड्वाहं १०. ५९, १०.
अनड्वाहौ १०. ८५, १०.
अनत् १. १६४, ३०.
अनतिऽद्भुता ८. ९०, ३.
अनदतीः ३. १, ६.
अननुऽकृत्यं १०. ६८, १०.
अननुऽकृत्या १०. ११२, ५.
अननुऽदः १. ५३, ८; २. २१, ४; २३, ११.
अननुऽदं १०. ३८, ५.
अननुऽदिष्टः १०. १६०, ४.
अननुऽभूतीः ६. ४७, १७.
अनंतः १. ११३, ३; ६. ६१, ८.
अनंतं १. ११५, ५; १०. ७५, ३.
अनंतऽशुष्माः १. ६४, १०.
अनंतान् ७. १०४, १७.
अनंतासः ५. ४७, २.
अनंते १. १३०, ३; ४. १, ७.
अनंतैः १. १२१, ९.
अनपऽच्युतः ४. ३१, १४; ८. ९३, ९; ९. ४, ८; १०. २६, ८.
अनपऽच्युतं ४. १७, ४; ५. ४४, ६; ८. ९२, ८; १०. ९३, १२.
अनपऽच्युता ८. २६, ७; ९. १११, ३[२].
अनपत्यानि ३. ५४, १८.
अनपऽवृज्यान् १. १४६, ३.
अनपऽवृत् ६. ३२, ५; १०. ८९, ३.
अनपऽव्ययंतः ६. ७५, ७.
अनपऽस्फुरः ८. ६९, १०.
अनपऽस्फुरंतीं ४. ४२, १०.
अनपऽस्फुरां ६. ४८, ११.
अनपिऽनद्धं ६. ७२, ४.
अनप्सं ९. १६, ३.
अनप्नसः २. २३, ९.
अनभिऽद्रुहा २. ४१, ५.
अनभिम्लातऽवर्णः २. ३५, १३.
अनभिऽशस्ता ९. ८८, ७.
अनभीशुः १. १५२, ५; ६. ६६, ७.
अनमत् २. २४, २.
अनमत् ६. १७, ९.
अनमं १. १६५, ६.
अनमयत् ७. ६, ५.
अनमस्यन् ६. ९, ७.
अनमस्युः १०. ४८, ६.
अनमीवः ७. ४६, २; ५४, १.
अनमीवं १०. १४, ११.
अनमीवस्य ३. १६, ३.
अनमीवाः ३. २२, ४; ६२, १४; १०. १७, ८; १८, ७; ३५, ६; ३७, ७.
अनमीवां १०. ९८, ३.
अनमीवासः ३. ५९, ३.
अनम्नत १. १३१, १.
अनयः २. १३, १२; ६. १, ७.
अनयत् ६. ४५, १; ५७, ४; ७. १८, ७.
अनयत् ३. ३३, ६; ८. ३३, १६; ७०, १५; १०. ९९, ९.
अनयत १०. ६१, २७.
अनयन् ६. १५, १७; १०. ५२, ७.
अनयन् १. ३१, ४; ७. ३३, २; १०. १५७, ५.
अनयंत ४. ३३, ७.
अनयंत १. १४१, १; ३. ७, ६; ५. ४५, १०; ६. २४, ६.
अनयं ४. २६, २.
अनया ९. ६५, १२; २७.
अनर्तिषुः १०. ९४, ४; ५.
अनर्वणः ५. ५१, ११; ८. ३१, १२.
अनर्वणं १०. ९२, १४.
अनर्वणा १०. ३६, ११; ६५, ३.
अनर्वन् १. ११६, १६.
अनर्वं १. १६४, २; १८५, ३.
अनर्वा १. ९४, २; २. ४०, ६; ४. १७, २०; ५. ४९, ४; ७. २०, ३; ४०, ४; १०. ६१, ५; १३; ९९, ३.
अनर्वाणः १. १९०, ६; ८. १८, २.
अनर्वाणं १. ३७, १; ५१, १२; १३६, ५; १९०, १; २. ६, ५; ६. ४८, १५; ७. ९७, ५; ८. ९२, ८.
अनर्विशे १. १२१, ७.
अनर्शनिं ८. ३२, २.
अनर्शऽरातिं ८. ९९, ४.
अनडुत्ऽसु ३. ५३, १८.
अनवः ५. ३१, ४; ७. १८, १४.
अनवद्य १. ३१, ९; १२९, १[२]; १७४, २; १०. १४७, २.
अनवद्यः ९. ६९, १०.
अनवद्यं १. ७१, ८.
अनवद्यऽरूपाः १०. ६८, ३.
अनवद्यस्य १. ३३, ६.
अनवद्या १. ७३, ३.
अनवद्याः १. १२३, ८; २. २७, २; ३. ३१, १३; ६. १९, ४.
अनवद्याभिः ४. ३२, ५.
अनवद्यासः ७. ५७, ५; ९१, १.
अनवद्यैः १. ६, ८.
अनवंत ८. ९६, ५.
अनवंत ५. ३०, १०; १०. ९५, ६.
अनवऽपृग्णा १. १५२, ४.
अनवऽब्रवः १०. ८४, ५.
अनवभ्रऽराधसः १. १६६, ७; २. ३४, ४; ३. २६, ६; ५. ५७, ५.
अनवसः ६. ६६, ७.
अनवऽस्यंतः ४. १३, ३.
अनवऽह्वरं २. ४१, ६.
अनवायं ७. १०४, २.
अनवि ८. १०, ५.
अनविष्ट ९. ७१, ७.
अनशामहै ८. २७, २२.
अनश्नन् १. १६४, २०.
अनश्रवः १०. १८, ७.
अनश्वः १. १५२, ५; ६. ६६, ७.
अनश्वऽदां ५. ५४, ५.
अनश्वं १. ११२, १२; १२०, १०.
अनश्वासः ५. ३१, ५.
अनष्टऽपशुः १०. १७, ३.
अनष्टऽवेदसं ६. ५४, ८.
अनष्टां ७. ४५, २.
अनसः ४. ३०, १०; ८. ९१, ७; १०. १०२, ६.

अनेसा ३. ३३, ९; १०.
अनस्थः ८. १, ३४.
अनस्था १. १६४, ४.
अनस्वंतः १. १२६, ५.
अनस्वंता ५. २७, १.
अना ४. ३०, ३; ८. २१, १३; ४७, ६; १०. ९४, ३; ४.
अनाकृतः १. १४१, ७.
अनागसः १. २४, १५; १२३, ३; २. २३, ७; ४. ५४, ३; ५. ८२, ६; ७. ६२, २; ८. ४७, १८; ६७, ७; १०. ३५, ३; ३६, ९; ३७, ७; ६३, ४.
अनागसं ४. ३९, ३; १०. ६३, १०.
अनागाः ५. ८३, २; ७. ६०, १; ६६, ४; ८६, ७; ८७, ७; ९७, २; १०. ३६, १२.
अनागाः १०. १६५, २.
अनागाःऽस्त्वं १. ९४, १५; १६२, २२; १०. ३५, २.
अनागाःऽस्त्वे १. १०४, ६; ६. ५०, २; ७. ५१, १.
अनागाःऽस्त्वेन १०. ३७, ९.
अनागान् ३. ५४, १९; ४. १२, ४; १०. १२, ८.
अनागां ८. १०१, १५.
अनातुरं १. ११४, १; ८. ४७, १०; १०. ९७, २०.
अनातुराः १०. ९४, ११.
अनाथं १०. १०, ११.
अनाधृष्टः ७. १५, १४.
अनाधृष्टं ८. २२, १८.
अनाधृष्टानि १०. १३८, ४.
अनाधृष्टाभिः ४. ३२, ५; ८. १०२, १५.
अनाधृष्टासः १. १९, ४.
अनाधृष्यं ४. १८, १०.
अनाधृष्या १०. ४४, ५.
अनाधृष्याः १०. १०३, १३; १५४, २.
अनानत ६. ४५, ९.
अनानतः ८. ६४, ७; ९०, ४.
अनानतं ७. ६, ४; १०. ७४, ५.
अनानतस्य ८. ६८, ४.
अनानताः १. ८७, १.
अनापिः ८. २१, १३; १०. ३९, ६.
अनाप्तः १. १००, २.
अनाप्यं ७. ६६, ११.
अनाभयिन् ८. २, १.
अनाभुवः १. ५१, ९.
अनामयित्नुऽभ्यां १०. १३७, ७.
अनामि ३. ६२, ५; ६. ८, ६.
अनामृणः १. ३३, १.
अनायतः ४. १३, ५.
अनायुधासः ४. ५, १४; ८. ९६, ९.
अनारंभणे १. ११६, ५; १८२, ६; ७. १०४, ३.
अनावन् १०. ६८, १.
अनाविद्धया ६. ७५, १.
अनावृत् १०. ९५, १४.
अनाशयः ८. १४, १५.
अनाशवः १. १३५, ९; ८. १, १४.
अनाशस्ताःऽइव १. २९, १.
अनाशीःऽदां १०. २७, १.
अनाशुना ६. ४५, २.
अनाशोः १०. ३९, ३.
अनासः ५. २९, १०.
अनास्थाने १. ११६, ५.
अनाहु ८. ४८, ५.
अनाहुतिं १०. ३७, ४; ६३, १२.
अनिःऽकृतं ८. ९९, ८; ९. ३९, २.
अनिःऽशस्ताः ४. ३४, ११.
अनितभा ५. ५३, ९.
अनिध्मः २. ३५, ४; १०. ३०, ४.
अनिनस्य १. १५०, २.
अनिंदिषुः १. १६१, ५.
अनिंद्यः ९. ८२, ४.
अनिंद्यां १. १८०, ७.
अनिंद्रं ७. १८, १६.
अनिंद्राः १. १३३, १; ५. २, ३; १०. ४८, ७.
अनिंद्रान् १०. २७, ६.
अनिंद्रां ४. २३, ७.
अनिऽपद्यमानं १. १६४, ३१.
अनिऽबद्धः ४. १३, ५.
अनिऽबाधे ३. १, ११; ५. ४२, १७.
अनिऽभृष्टः १०. ११६, ६.
अनिभृष्टऽत्तविषिः २. २५, ४; ५. ७, ७.
अनिऽमानः १. २७, ११; ६. २२, ७.
अनिऽमिषः १०. १०३, १.
अनिमिषत्ऽभिः १. १४३, ८.
अनिऽमिषंतः १०. ६३, ४.
अनिऽमिषं ५. १९, २; ७. ६१, ३.
अनिऽमिषं १. २४, ६.
अनिऽमिषा ३. ५९, १; ७. ६०, ७.
अनिऽमिषाः २. २७, ९.
अनिऽमिषेण १०. १०३, २.
अनिऽमेषं १. ३१, १२; १६४, २१.
अनिराः ८. ४८, ११.
अनिरां ७. ७१, २; ८. ६०, २०; १०. ३७, ४.
अनिरेण ४. ५, १४.
अनिऽविशमानाः ७. ४९, १.
अनिऽवृतः ३. २९, ६.
अनिऽवेशनानां १. ३२, १०.
अनिऽशितं २. ३८, ८; ९. ९६, २.
अनिशितऽसर्गाः १०. ८९, ४.
अनिषंगाय १. ३१, १३.
अनिषव्याः १०. १०८, ६.
अनिऽस्तृतः ८. ३३, ९.
अनीकं १. ११३, १९; ११५, १; १२१, ४; १२४, ११; १६८, ९; २. ३५, ११; ३. ३०, १३; ४. ५, ९; १५; ११, १; १२, २; ५. २, १; ४८, ४; ७६, १; ६. ४७, २८; ५१, १; ७. १, ८; ९; ८८, २; ८. ९६, ९; १०. २, ६; ७, ३; ४३, ४; ४८, ३; ६९, ३.
अनीका ३. १९, ४; ४. २३, ७.
अनीके ४. ५८, ११; ६. ४७, ५; ७. ४, ३; ८. ७४, ४; १०२, १३; ९. ९७, २२.
अनीकेन २. ९, ६.
अनीकेषु ८. २०, १२.
अनीकैः ३. १, १५; ४. १०, ३; ७. ८, ५.
अनीतां १. १२१, ५.
अनीनशत् १०. १६२, २.
अनीयत ८. ५६, ४.
अनीळः १०. ५५, ६.
अनु १. ६, ४; ५; १०, १२; १५, ५; २३, २३; २५, १६; ३०, ९; ३२, १; ३३, ११; ३४, २; ३७, ९; ३८, ११; ४४, १०; ४६, १४; ४९, ३; ५०, ३; ६; ५२, ४; ९;

११; १४; १५; ५७, २; ५; ६१, १५; ६५, १; २; ७१, ६; ८०, १–७; ८^{२}; ९^{२}; १०–१६; ८२, ३; ८४, ६; १०–१२; ८५, ३; ८६, ३; ८८, ६; ९१, १; २१; ९५, ३; १०२, १; १०३, ७^{२}; ११३, ८; १०; १३; ११६, १७; १२०, ११; १२१, २; ३; ७; ११; १२४, ३; १२६, ३; ५; १२७, १; ४; १२८, १^{२}; १३२, ३; १३४, १; १३६, ५; १३८, ३; १४०, ९; १४१, ३; ५; ९; १४७, २; ४; १४८, ४^{२}; १६१, ३; ११; १६२, ७; १६३, ७; ८^{२}; १२; १६४, ९; २८; १६५, ५; १६६, १०; १६७, १०^{२}; १७३, ८; १७५, ६; १७६, २; ६; १८०, ८; १८१, ५; १८२, ८; १८३, २; ३; १८४, ४; १८५, ४; १८७, ४; १९०, ५; १९१, १५; **२.** १, १०; १५; २, ४; ५; ८; ५, ३; ४; ८, ५; १३, ३; १०; १३; १४, १२; १६, ३; २०, ८; २१, ३; २४, १३^{२}; २८, २; ६; ३०, २; ३१, ३; ३६, ६; ३७, १; ३८, ३; ५–७; ४२, २; ४३, १; **३.** १, १७; ४, ७; ६, ७; ७, ६^{२}; ७; ९, ४; १२, ७; १५, ३; १७, १, ५; २३, २; २६, ८; ३०, ४; ३१, १७; ३२, ११; ३३, ३; ४; ३४, ८; ३५, ८; ३९, ८; ४३, १; ४७, ३; ५०, २; ५१, ९–११; ५५, ४; ७; ६१, १; **४.** ४, १; २; ८; ९; ११; १३, २; १६, १८; १७, १; ५; १८, ३^{२}; ११; २०, २; २२, ७^{२}; २६, २; २७, १; २९, ३; ३०, २; १९; ३२, २२; ३३, ६; ३५, १; ३७, ४; ३८, ३; ५; ४०, ३; ४^{२}; ४५, ६; ४८, ३; ५२, ६; ५७, ३; ७; ५८, ४; **५.** २, ८; ११, ६; १२, २; २९, २; ५; ३०, २; ३२, १०; ३३, २; ३४, १; ३६, २; ४०, ९; ४४, १; ३; ४६, ४; ४९, ४; ५१, १५; ५२, ६; ५३, २; ५; ६; १०; ११; १६; ५४, ६; ५५, १; ५९, १; ६१, १९; ६२, २; ४; ५; ६९, १; ७३, ४; ७८, २; ८१, २; ३; ८६, ५; **६.** १, २; ३; १५, ९; १७, १२; १८, १४; १५; २०, २; २१, ६; २३, ८; २५, ८^{५}; २८, ४; ३६, २^{२}; ४६, १४; ४७, ८; ४८, २२; ५२, १; ५४, ५; ६; ६३, ६–८; ६४, ५; ६६, ४^{२}; ६७, ६; ११; ७२, ३; ७५, ६; १८^{२}; **७.** ७, २; १८, १२^{२}; २५; २१, ७; ३१, ७; ९; ३३, ७; ३४, २४^{२}; ३८, ६; ४५, २; ५६, १३; ६३, ५; ७०, ४; ७६, ४; ७७, ३; ८२, ३; ८७, ७; ९०, ४; ९९, १; १०३, ४; **८.** १, १४; २८; ३४; २, ३३; ३, ८; ४, ८; १०; २०; ६, ३८^{२}; ७, १६; २४^{२}; ९, २; १०, ६; ११, ८; १३, ६; १५, ६; ९; १७, ५; १९, ३५; २०, ७; २१, १८; २५, १६; १७; ३२, १९^{२}; ४०, ८; ४१, ३; ७; १०; ४३, ९; ४७, ११; ४८, २; १३; ४९, ३; ५८, २; ६१, ५; ६२, ७; ११; ६३, ५; ७०, ५; ८८, ५; ९६, १६; ९९, ६; १०३, २; **९.** २, ४; ६, ४; ८, ४; १७, ८; २२, ६; २३, २; २९, १; ५४, १; ६३, ६; ७०, ३; ४; ७२, ३; ८२, ५; ८६, २४; ४२; ९२, ३; ९६, १८; ९७, ५; ३२; ५५; १०३, ५; १०९, ७; ११०, २; १११, ३; ११२, ३; ११४, १; **१०.** २, ३; ६; ७; ६, ७; ११, ३; १२, ३; १३, ३^{२}; १४, १; २; १२; १७, ५; ११^{४}; १८, १; १९, १; २७, ५; १३; १७; **२८**, ८; २९, २; ३७, ३; ५^{२}; ४०, ९; १०; ४३, ५; ४५, ११; ४६, २; ५१, ६; ५३, ६; ५६, ३^{२}; ५; ६१, २१; ६३, ३; ६६, ८; १३; ६७, ९; ६८, १२; ७१, ३; ७२, ३; ५; ७३, ८; ८५, १४; ३१; ८७, १९; ८९, १३^{६}; ९१, ७; ९५, ५; ९७, १९; १०३, ६^{२}; १०५, २; १०६, ९; १०९, ५; ११३, १; ११५, ६; ११७, ५; १२०, १; १२२, २; १२४, ९; १२५, ७; १३५, १; ४; १३६, २; १४२, ७; १४५, ६; १४७, १; १४९, ३; १५९, २; १६८, २.

अनुऽअर्तिता **१०.** १०९, २.
अनुऽअविंदत् **२.** १२, ११.
अनुऽअवैत् **१०.** १३९, ४.
अनुऽआलेभिरे **१०.** १३०, ७.
अनुऽऊहिरे **१०.** १५, ८.
अनुऽएतवे **७.** ३३, ८.
अनुऽएतवै **१.** २४, ८; **७.** ४४, ५.
अनुऽएषि **१०.** १४२, ५.
अनुकामऽकृत् **९.** ११, ७.
अनुऽकामं **१.** १७, ३; **८.** ४८, ८; **९.** ११३, ९.
अनुऽकामा **८.** ९२, १३.
अनुक्थाः **५.** २, ३.
अनुऽक्षरंति **८.** ६९, १२.
अनुऽगायसं **८.** ५, ३४.
अनुऽग्मन् **३.** ३९, ५.
अनुग्रः **७.** ३८, ६.
अनुग्रासः **८.** १, १४.
अनुऽघुष्यं **१.** १६२, १८.
अनुऽचक्रदे **८.** ३, १०.
अनुत्तं **१.** ८०, ७; १६५, ९; **७.** ३४, ११.
अनुत्तऽमन्युः **८.** ९६, १९.
अनुत्तऽमन्युं **७.** ३१, १२; **८.** ६, ३५.
अनुत्ता **८.** ९०, ५.
अनुत्ताः **३.** ३१, १३.
अनुदः **१०.** १८०, ३.
अनुदकाः **७.** ५०, ४.
अनुऽददाति **२.** १२, १०.
अनुदितासः **१०.** ९५, १.
अनुऽदृश्यं **१०.** १३०, ७.
अनुदेयी **१.** ११६, ९.
अनुऽदेयं **६.** २०, ११.
अनुऽदेयी **१०.** ८५, ६; १३५, ५; ६.
अनुऽग्रे **१०.** ११५, ६.
अनुऽधूपितासः **२.** ३०, १०.
अनुऽनोनुवतः **८.** ९२, ३३.

अनुपऽक्षितं ३. १३, ७; १०. १०१, ५.
अनुऽपथाः ५. ५२, १०.
अनुऽपस्पशानं १०. १४, १.
अनुऽपूर्वं १. ११७, ३; १०. १८, ५; ६; १३१, २.
अनुऽप्रुवाणः ५. ४४, १३.
अनुऽभर्त्री १. ८८, ६.
अनुऽभृतं १०. ६१, ५.
अनुऽमते १०. ५९, ६.
अनुऽमत्याः १०. १६७, ३.
अनुऽमदति १. १७३, ७; ३. ४७, ४; १०. १२०, ४.
अनुऽमदाम १. १०२, ३.
अनुऽमद्यमानः ७. ६३, ३; १०. ९८, ८.
अनुऽममृजानः १०. १४२, ५.
अनुऽमाद्यः ६. ३४, २; ९. २४, ४; ६; ७६, १; १०७, ११.
अनुऽमाद्यस्य ७. ६, १.
अनुऽमाद्यासः १. ११५, ३.
अनुऽमृश्य १०. ६८, ५.
अनुऽयच्छमाना १. १२३, १३.
अनुऽयच्छमानाः १. १०९, ३.
अनुऽयतं ५. ४१, १३.
अनुऽयाजः १०. १८२, २.
अनुऽयाजाः १०. ५१, ९.
अनुऽयाजान् १०. ५१, ८.
अनुऽयाति ६. ६, २; १२, ५.
अनुल्बणं १०. ५३, ६.
अनुल्बणेन ८. २५, ९.
अनुऽवाति ४. ७, १०.
अनुऽवित्तः ४. १८, १.
अनुऽवेद १. १६४, १८.
अनुऽवेनतं १०. १३५, २.
अनुऽव्रतः ८. १३, १९.
अनुऽव्रता १०. ३४, २.
अनुऽव्रताय १. ५१, ९.
अनुऽव्रते १. ३४, ४.
अनुऽशसे ५. ५०, २.
अनुऽशासता १. १३९, ४.
अनुऽशासति ६. ५४, १.
अनुऽशासनस्य १०. ३२, ७.
अनुऽशिष्टः ५. २, ८; १०. ३२, ७.
अनुष्टु १. १०८, ८.
अनुष्टु १. ९५, ३.
अनुष्टुया ४. ४, १४.
अनुऽसत्यं ३. २६, १.
अनुऽसेसिधत् १. २३, १५.
अनुऽस्तुतिः ८. ६३, ८.
अनुऽस्तुतिं ८. ६८, ७.
अनुऽस्तुभं १०. १२४, ९.
अनुऽस्तुभा १०. १३०, ४.
अनुऽस्थाः १. ५४, १०.
अनुऽस्थितं १०. ६१, ५.
अनुऽस्पष्टः १०. १६०, ४.
अनुऽस्यदे २. १३, २.
अनुस्तऽयाम्ने ४. ३२, २४.
अनुऽस्वधं १. ८१, ४; २. ३, ११; ३. ६, ९; ४७, १; ५. ५२, १; ९. ७२, ५.
अनुऽस्वापं ८. ९७, ३.
अनूक्यात् १०. १६३, २.
अनूचः ३. ३०, ६.
अनूचानः ८. ५८, १.
अनूची इति १. ११३, २.
अनूचीना ४. ५४, २.
अनूती ६. २९, ६.
अनूधाः १०. ११५, १.
अनूनं १. १४६, १; २. १०, ६; ४. २, १९; ६. १७, ४.
अनूनऽवर्चाः १०. १४०, २.
अनूनस्य ८. ५५, ५.
अनूना ७. २७, ४.
अनूनाः ३. १, ५; ८. १६, ४.
अनूनेन ४. ५, १.
अनूनोत् ५. ४५, ७.
अनूपाः १०. २७, २३.
अनूपे ९. १०७, ९.
अनूरुत् ३. ५५, ५.
अनूर्ध्वऽभासः ५. ७७, ४.
अनूर्मि ८. २४, २२.
अनूषत ४. ३२, ९; ८. ९, १९; १२, १५; ९. ८०, २.
अनूषत १. ६, ६; ७, १; ११, ८; १४४, २; १५१, ६; ३. ५१, १; ४. १, १६; ५. ५, ४; ६. ६०, ७; ८. ३, ३; ६, ३४; १२, २२; ५२, ९; ६३, ५; ६९, ११; ९५, १; ९. १२, २; १७, ६; २६, २; ३२, ५; ३३, ५; ३९, ६; ४५, ५; ५६, ३; ६४, २१; ६५, १४; ६८, ८; ८६, १७; ३१; ९९, ४; १०१, ८; १०४, ४; ११०, ६; १०. ४३, १; १२३, २.
अनूषातां ८. ८, १२.
अनूषि ६. ३८, ३.
अनृक्षरः २. ४१, ४; २. २७, ६.
अनृक्षरा १. २२, १५.
अनृक्षराः १०. ८५, २३.
अनृचः १०. १०५, ८.
अनृजोः ४. ३, १३.
अनृतऽदेवः ७. १०४, १४.
अनृतऽद्विषः ७. ६६, १३.
अनृतं १. २३, २२; १०५, ५; १३९, २; १५२, ३; ७. २८, ४; ८. ६२, १२; १०. १०, ४; १२४, ५.
अनृतस्य ५. १२, ४; ७. ६०, ५; ६५, ३; ८६, ६; १०. ६७, ४; १००, ७.
अनृता २. २४, ६; ७; ७. ६१, ५; ८४, ४.
अनृताः ४. ५, ५.
अनृतानि १. १५२, १; २. ३५, ६.
अनृतुऽपाः ३. ५३, ८.
अनृतेन १०. ८७, ११.
अनृतेभिः ७. १०४, ८.
अनेद्य ८. ३७, १.
अनेद्यः १. ८७, ४; १६५, १२; ५. ६१, १३.
अनेद्याः ६. १९, ४.
अनेनं १. ९३, १०; ३. १७, २; ८. ४४, २.
अनेनः ६. ६६, ७.
अनेनाः १. १२९, ५; ७. २८, ४; ८६, ४.
अनेषत १०. १५५, ५.
अनेहः १. १८५, ३; ६. ५०, ३; ८. १८, २१; ३१, १२; ६७, १२.
अनेहसः ३. ५१, ३; ५. ६५, ५; ८. १८, ५; ४५, ११; ४७, १; १०. ६१, २२.

अनेहसं १. ४०, ४; ६; ३. ९, १; ६. ५१, १६; ८. २२, २; ४९, ४; ५०, ४; ६९, १६; १०. ६३, १०.

अनेहसा १. १२९, ९; ६. ७५, १०.

अनेहा १०. ६१, १२.

अनोनवुः १. ८०, ९; ८. ७०, ४.

अंतः १. ५४, १; १६४, ३५; ६. २९, ५; १०. १११, ८.

अंतः १. २३, १९; २०; २४, ७; ३५, ९; ५४, १०; ७०, २; ८१, ९; ९५, १०; ९६, ५; १०५, १; १३०, ३; १३५, ९; १६०, १; १६१, ४; १६४, ३२; ३३; १६८, ५; १७३, ३; १८०, ३; १८२, ६; १९०, ७; २. ६, ७; १२, ३; २७, ८; ३५, ७; ३. १, ३; १४;३, २; ६; ६, ४; ३८, ३; ४४, ३;५५,२; ८; ९; १२; ४. १, १३; २, २; ३; ८, ४; १६, १७; १८, ४; ५८, ६; ११; ५. ३०, ९; ३१, ३; ५९, २; ६. ११, २; २७, ७; ४३, ३; ७२, ४; ७. २, ३; ४, १; ११, ३; १२, १; १८, २४; ८६, २; ८७, २; ५; १०४, ३; ८. २, ४; २९, २; ३; ६८, १८; ७२, ३; १०१, १३; ९. ६७, २३; ६९, २; ७२, ७; ७३, ८; ७८, ३; ८२, ४; ८६, ४; ४२; ८७, ८; ८९, ५; १०७, १; १०८, ६; १०. ४, २; ५, ५; ८. ७; १८, ४; ३०, ४; ३९, १३; ४२, ८; ४५, ३; ४८, १०; ५४, ६; ६१, १; ८०, ३; ८६, १५; १०१, ११; १०२, ३; १०६, ११; १२४, ४; १६२, ४; १७३, १.

अंतःऽपथाः ५. ५२, १०.

अंतःऽपेयं १०. १०७, ९.

अंतःऽवतीः ३. ५५, ५; १०. ९१, ६.

अंतःऽवावत १. ४०, ७; ६. ८, ३.

अंतःऽविद्वान् १. ७२, ७.

अंतकऽध्रुक १०. १३२, ४.

अंतकं १. ११२, ६.

अंत १. ३३, १०; ३७, ६; ५२, १४; १००, १५; १६४, ३४; १६७, ९; १७९, २; ५. १५, ५; ६. ४३, २; ७. २१, ६; ९९, २; ८. ४६, ११; १०. ५४, ३; ११४, १०.

अंतमः ३. १०, ८; ५. २४, १; ६. ४५, ३०; ४६, १०; ८. ५, १८; १३, ३; ४५, १८; ६४, ९; १०. १००, ६.

अंतमं ८. ३३, १५.

अंतमस्य १. २७, ५.

अंतमस्यं ३. ५५, ८.

अंतमा ७. २२, ४.

अंतमाः ६. ५२, १४.

अंतमानां १. ४, ३.

अंतमेभिः १. १६५, ५.

अंतरऽआभरः ८. ३२, १२.

अंतरः १. ३१, १३; ४४, १२, २. ४१, ८; ६. ५, ४; ६३, २; ८. १८, १९; १०. ५३, १.

अंतरं १. १०, ९; ६. ७५, १९; ७. १०१, ५; १०. ८२, ७.

अंतरस्य ६. १५, ३.

अंतरा १०. ९१, १३.

अंतरा ३. ४०, ९; ९. ८६, १३; १०. ८६, १६; ८८, १५; १३९, २; १६२, ४.

अंतरान् ३. १८, २.

अंतरां १. १०४, ६.

अंतरिक्षऽप्राः ७. ४५, १; ९. ८६, १४.

अंतरिक्षऽप्रां १. ५१, २; १०. ९५, १७.

अंतरिक्षप्रुत्ऽभिः १. ११६, ३.

अंतरिक्षं १. ५२, १३; ७३, ८; ८९, १०; ९१, २२; ११५, १; २. १२, २; १५, २; ३. ८, ८; २२, २; ३०, ९; ३४, १०; ५४, १९; ४. ५२, ७; ५३, ५; ५७, ३; ५. १, ११; ४२, १६; ५४, ४; ५५, २; ८५, २; ३; ६. ८, २; ४७, ४; ६१, ११; ६९, ५; ७. ३५, ५; ९८, ३; १०४, २३; ८. १४, ७; ९. ८१, ५; १०. ५९, ७; ६५, २; ६६, ९; ११; ८८, ३; ८९, ६; ९०, १४; १२४, ६; १२८, २; १३९, २; १४९, १; १५३, ३; १९०, ३.

अंतरिक्षऽसत् ४. ४०, ५.

अंतरिक्षस्य १. ११०, ६.

अंतरिक्षा ६. २२, ८; ७. ७५, ३.

अंतरिक्षाणि १. ३५, ७; ८. ६, १५; १२, २४; १०. ४४, ८; ६५, ४.

अंतरिक्षात् १. ४८, १२; ६१, ९; ३. ३०, ११; ४६, ३; ५. ५३, ८; ८. ३, २०; ८, ३; ४; ९. ६३, २७; १०. ६८, ५; ७०, ११; ८९, ११; १५८, १.

अंतरिक्षे १. ३५, ११; १६५, २; २. १४, ३; ३०, ३; ४०, ४; ३. ६, ८; ५. ५२, ७; ७३, १; ८५, ५; ६. ४६, ११; ५२, १३; ५८, ३; ७. ३९, ३; ८. ९, २; १०, ६; ९७, ५; ९. २७, ६; १०. ५, ५; ८०, ५; ८७, ३; ६; १२१, ५; १६८, ३.

अंतरिक्षेण १. २५, ७; १६१, १४; ८. ७, ३५; ९. ५, २; ६३, ८; ६५, १६; १०. १३६, ४.

अंतरिक्ष्या ९. ३६, ५; ६४, ६.

अंतरिक्ष्याः ५. ५४, ९.

अंतरिति १. ६२, ९; ६७, ५; ११६, २४; १३२, ३; १५७, ५; १५९, ४; १६३, ४; १६४, ९; १७; ३१; २. २७, ३; ४०, २; ३. ३१, २१; ५४, ९; ५५, ५; १५; ५८, १; ४. १, ७; ७, ८; १३, ४; २७, ४; ५१, ३; ५८, ११; ५. ६२, ५; ६; ६. ४, ४; ९, ५; ४४, २३; २४; ५८, ३; ६६, ४; ७२, ४; ७. ७१, ५; ८. ३९, १; ४८,२; १००, ९; १०१,९; १४; ९. १२, ५; ७; १५, ३; ७०, ५; ९६, ७; १०. २७, ९; १७; ४५, ४; ४६, ६; ४८, १०; ५७, १; ७९, ३; १२५, ७; १७७, १; २; १८३, ३; १८९, २.

अंतरेण १०. ३३, १.

अंतरैः ६. ६२, १०.

अंता ४. १, ११.

अंताः **७.** ६७, २; ८३, ३; **१०.** ८२, १.

अंतात् **१.** ३०, २२; **३.** ६१, ४; **१०.** ८९, ११.

अंतान् **१.** ९२, ११; **४.** ५०, १; **५.** ४७, ४; ५९, ७; **६.** ६२, १; **७.** ४५, २; ६९, ३; **८.** २५, १८; **१०.** ८, १; २०, ४; ८९, १; १०८, ५.

अंतिं **१.** ७९, ११; ८४, १७; ८९, ९; ९४, ९; १६७, ९; १७६, १; **२.** २७, ३; **४.** २, १८; ४, ३; ५, १०; **५.** ४४, ११; ७६, २; **८.** ११, ४; ७३, १; **९.** १९, ७; ६७, २१; ९१, ४.

अंतिऽऊर्तिं **१.** १३८, १.

अंतिकं **१०.** १६१, २.

अंतिके **९.** ७८, ५.

अंतिऽगृहात् **१०.** ९५, ४.

अंतितः **१.** १७९, ५; **२.** २७, १३; **३.** ५९, २; **५.** १, १०; **८.** २७, ९; **१०.** ११४, ४.

अंतिऽदेवं **१.** १८०, ७.

अंतिऽवामा **७.** ७७, ४.

अंते **४.** १६, २; **१०.** ३४, ११.

अंतेभ्यः **१.** ४९, ३; **८.** ८८, ५.

अंतेषु **७.** ७९, २.

अंतौ **५.** ४७, ३.

अंधः **१.** ६२, ५; ९४, ७; १२२, १; १५३, ४; **२.** १४, १; **३.** ३५, १; **४.** १, १९; १६, १; २३, १; २७, ५; **५.** ३०, ६; ४५, ९; **६.** ६३, २; ६८, ११; **७.** २१, १; ८८, २; ९२, १; **८.** २, १; **९.** ६२, ५; ६८, ६; ८६, ४४; **१०.** ११६, ४.

अंधः **१.** १६४, १६; **४.** १९, ९; **८.** ७९, २.

अंधं **१.** ११२, ८; ११६, १६; १४७, ३; **२.** १३, १२; **४.** ३०, १९; **१०.** २५, ११.

अंधसः **१.** ९, १; ५२, ३; ८०, ६; ८२, ५; ८५, ६; १३५, ४; १५५, १; **२.** १४, ५; १९, १; ३६, ३; ३७, १; **३.** ४०, १; ४१, ६; ४८, १; **४.** ३१, २; ३२, १४; **५.** ३४, २; ५१, ५; **६.** ४२, ४; ४३, ४; ६३, ३; **७.** २१, १; ९०, १; **८.** १, २५; १३, १५; २१; १७, ४; ८; २४, १६; ३२, २८; ३३, ४; ७; ३५, २४; ४६, १४; ६१, ३; ६५, २; ६६, २; ७८, १; ८८, १; ९२, १; ४; ९५, २; **९.** १८, २; ५१, ३; ५५, २; ५८, १; ६१, १०; १०१, १; १३; **१०.** २५, १; ३२, १; ५०, १; ७; ७६, ६; ९४, ८; ९६, ९; ११५, ३; १४४, ५; १६७, २.

अंधसा **१.** ५२, २; ५; **४.** २०, ४; **५.** ५४, ८; **७.** २०, ४; **९.** १, ४; १६, २; ५२, १; ५५, १; ३; ६१, १९; ६७, २; १०७, २.

अंधसी इति **७.** ९६, २.

अंधस्य **१०.** ३९, ३.

अंधा **४.** १६, ४.

अंधांसि **१.** २८, ७; **४.** ६९, ७; **७.** ५९, ५; ६८, २; ७३, ४.

अंधांसिऽइव **५.** ४१, ३.

अंधाः **१.** १४८, ५.

अंधां **१०.** २७, ११.

अंधाय **१.** ११७, १७; १८.

अंधे **१.** १००, ८.

अंधेन **१०.** ८९, १५.

अन्नंऽकामाय **१०.** ११७, ३.

अन्नं **१.** १४०, २; **२.** २४, १२; ३५, ५; ७; १०; ११; १४; **३.** ४८, ३; **४.** २, ७; ११, १; १२, १; **६.** ४, ४; ५; ४१, ३; **७.** ९८, २; **८.** ४, १२; **१०.** ५९, २; ६१, ४; ६९, २; ७९, ५; ९१, ५; ९९, ५; १०७, ७; ११२, ४; ११३, ८; ११७, ६; १२५, ४.

अन्नंऽवान् **१०.** ११७, २.

अन्नंऽवृधे **१०.** १, ४.

अन्ना **१.** ६१, ७; १२२, १३; १२७, ४; **३.** ३६, ८; **४.** ७, १०; ११; **५.** ८, ५; **७.** ३, ४; ४, २; **१०.** ९१, ७.

अन्नियते **४.** २, ७.

अन्ने **१०.** २९, ४.

अन्नेन **१०.** ९०, २.

अन्नेषु **२.** २३, १६.

अन्नैः **२.** १०, ४; ३५, १२; **३.** ५०, १; **१०.** १, ४; ५, ४; २८, ११; २९, ३; ५.

अन्यऽउदर्यः **७.** ४, ८.

अन्यः **१.** ५२, १३; ५७, ४; ८४, १९; १२५, ७; १६१, ९; १६४, २०[२]; १८१, ४[२]; **२.** ४०, ४[२]; ५[२]; **३.** ३१, २[२]; **५.** ३२, ३; ७७, २; **६.** २१, १०; ३०, ४; ४८, २२; ५२, १६[२]; ५७, २[२]; ६८, ३[२]; **७.** ३२, २३; ३६, २; ५६, १५; ८२, २[२]; ५; ६[२]; ८३, ९[२]; ८५, ३[२]; १०३, ३–५; **८.** ५, ३९; १५, ११; ६६, १३; ७८, ४; **१०.** १०, १४; २८, १; ३४, १४; ४३, ५; ६४, २; ८५, १८[२]; ११९, ११; १३२, ४; १३७, २[२]; १४६, ५.

अन्यऽकृतं **६.** ५१, ७.

अन्यऽकृतेन **२.** २८, ९.

अन्यऽकृतेभ्यः **८.** ७९, ३.

अन्यके **८.** २१, १८; ३९, १.

अन्यकेषां **१०.** १३३, १.

अन्यऽजातं **७.** ४, ७; ५२, २.

अन्यत् **१.** ३०, १९; ५२, १४; १०३, १[२]; ११५, ५[२]; १२३, ७[२]; १४०, ७; **३.** ५५, ११; १५[२]; **५.** २९, १०[२]; ३१, २; ७३, ३; **६.** २४, ५[२]; ५८, १[२]; ६६, १; **७.** ३२, १९; **८.** १, १; २, १७; २२, ४; **१०.** २७, २१; ३१, ८; ३७, २; ३; ८२, ७; १२९, २; १४२, १; १४९, ३.

अन्यतः **१.** ४, ५.

अन्यत्ऽअन्यत् **२.** २४, ५; **३.** ३८, ७.

अन्यत्र **७.** ५९, ५; **८.** २४, ११; **१०.** ८६, २.

अन्यथा **४.** ३२, ८; **६.** ३५, ५.

अन्यं **१.** ९३, ६^{२}; १२९, १०; १६४, ३८^{२}; **२.** २२, २; ३३, ११; **५.** ३४, ८; **६.** ४७, २१; **७.** १०३, ३; ४; **८.** २४, १२; ७५, १३; ८०, १; ९६, १९; **१०.** १०, १०; १४; ४९, ८; ९१, ८; ११७, ४; ११९, ७; ११; १४२, ७.

अन्यंऽअन्यं **५.** ४४, ११; **६.** ४७, १५; १६; **१०.** ११७, ५.

अन्यया **३.** ३२, ११.

अन्यऽरूपः **७.** १००, ६.

अन्यऽरूपाः **१०.** १, ४.

अन्यऽव्रतः **१०.** २२, ८.

अन्यऽव्रतं **८.** ७०, ११.

अन्यऽव्रतस्य **५.** २०, २.

अन्यस्मिन् **३.** ५५, १७.

अन्यस्य **१.** १४०, २; १७०, १; १८१, ५; ६; **६.** ५७, ३^{२}; **७.** १०३, ५; **८.** ३३, १६.

अन्यस्यऽइव **२.** ३५, १३.

अन्यस्याः **२.** १८, २; **३.** ५५, १३; **९.** ७९, ३; **१०.** ९७, १४; १२४, ३.

अन्यस्यां **१.** ९५, १^{२}.

अन्या **१.** १०९, १; ६; १२३, ७; १६१, ५; **२.** ३५, ८; **३.** ३३, २; ५५, ४; **५.** ७३, ३; **६.** ४९, ३^{२}; **७.** २६, ३; **९.** ७०, १; **१०.** १०, १३; ८२, ३; ९७, १४^{२}.

अन्याऽअन्या **१.** ६२, ८; ९५, १; ११३, ३.

अन्याः **१.** १२३, ११; **२.** ३५, ३^{२}; **६;** ६१, ९; १३; **७.** ९५, १; **८.** १०१, १४.

अन्यान् **३.** ४६, २; ४८, ३; **४.** ३६, ९; **५.** १, ८; ९; ३०, २; **६.** १०, ५; **७.** १, १४; **८.** १, ३३; ५, १३.

अन्याभिः **१.** ११३, १०.

अन्यां **८.** १, १०.

अन्यां **३.** ३३, २; **१०.** ८५, २१; २२; ९७, १४.

अन्यांऽअन्यां **१.** १३१, ५.

अन्यांऽइव **८.** २७, ११.

अन्यासां **१०.** १५९, ५.

अन्यासु **३.** ५५, १७.

अन्ये **१.** ३६, १; ५९, १; १६४, १२; **२.** १८, २; ३; **३.** ९, ३^{२}; **४.** १, १४; ४४, ५; **५.** ४०, ९; ८१, ३; **७.** ५७, ३; ६९, ६; **८.** २, ६; ३, २३; ८, ८; १९, ३३; **१०.** १४, ३; ३४, ४; ८१, ६; ११४, ७; १६०, १.

अन्ये इति **५.** ४७, ५.

अन्येन **१.** १४०, २; **६.** ९, ३; **७.** ३३, ८; **१०.** १०, ८; १२; ३७, ३.

अन्येभिः **२.** १८, २.

अन्येषां **८.** ३३, १४; **१०.** ३४, १०; ११.

अन्येषु **१.** ३०, ६.

अन्यैः **१.** १६१, ५.

अप **१.** ७, ६; १०, ७; ११, ५; ३२, ११; ३५, ३; ९; ४२, २; ३; ४८, ८^{२}; ५०, २; ५१, ३–५; ८५, ३; ९०, ३; ९२, ४; ११; ९४, ९; ९७, १^{२}; २–८; ११३, १४; १६; १२१, ४; १२३, ७; १२४, ८; १२९, ५; १३०, ३; १३१, ७; १३२, ४^{२}; ६; १३५, ८; १६१, १०; १६७, ४; **२.** २, ७; ११, १८; १४, ३; २३, ७; ३४, १; १२; ४१, १०; **३.** ५, १; १६, ५; २४, १; ३१, २१; ३३, ६; ४३, ७; ४४, ५; ४७, २; **४.** २, १६; ५, ८; १८, ९; २७, २; २८, १; २; ३०, १०; ३१, १३; ३४, ११; ३५, १; ५५, ६; **५.** २, ८; २०, २^{२}; २९, १२; ३१, ७; ४०, ८; ४५, १; ६; ४८, २; ६१, १८; ८०, ५; ८७, ८; **६.** ६, ६; १७, ५; ९; २०, ५; २१, ७; ४५, २४; ४७, २१; २९; ३०; ५१, १३; ५९, ८; ६०, ६; ६१, १४; ६४, ३; ७५, ४; **७.** १, ७; २७, २; ५०, २; ५६, २०; ५९, १०; ७१, १; ७५, १; ७८, २; ८१, ६; १००, ६; १०४, १७; २३; **८.** ५, २१; ११, ३; १८, ७–९; १०^{३}; २०, १; २३, २९; ४३, २३; २६; ४५, ४०; ४७, १८; ४८, ११; ६०, २०; ६३, ३; ६६, १५^{२}; ६७, १५; ७९, ९^{२}; ८९, २; ९६, ९; १३; **९.** ४, ३; ८, ७; १०, ६; १३, ८; २७, १; ४१, १; ६१, २५; २८; ६३, २६; २८; ७३, ५; ६; ८५, १; ८६, २३; ९६, ११; ९७, ४३; ५४^{२}; १०१, १; १३; १०२, ८; १०४, ६; १०५, ६; ११०, १२; **१०.** ११, ९; १४, ९; १७, २; २५, ७; २७, २४; २८, ७; ३४, २; ३; ३५, ३; ३६, ४; ३७, ४^{२}; ४०, ८; १३; ४२, ७; ४३, २; ५९, ८; ६१, ५; ८; ६३, १२^{३}; ६७, ११; ६८, ५; ७२, ६; ७३, ११; ७६, ४; ८३, ५; ८४, ७; ८५, ३२; ९५, ८; ९८, १२^{२}; १००, ८^{२}; १०५, ३; १०६, २; १०८, ९; १०; ११७, ४; ७; १२४, ८; १२७, ३; १२८, ९; १३०, १; १३१, १^{४}; १३९, ६; १४२, १; १४६, ४; १५२, ५^{२}; १६४, १^{२}; ३; १७२, ४; १७३, २; १७५, २^{२}; १८०, ३; १८२, १.

अपऽअर्जन् **१०.** ३, १.

अपऽअनती **१०.** १८९, २.

अपऽअप **५.** ३४, ३.

अपऽअवपः **१.** १३३, ४.

अपऽअवपत् **२.** १४, ६.

अपऽअवृणोः **८.** १००, ६.

अपऽआकृति **८.** ४७, २.

अपऽआवृक्ताः **८.** ८०, ८.

अपऽउदकाभिः **१.** ११६, ३.

अपऽऊर्णुतः **८.** ४०, ५.

अपऽऊर्णुते **१.** १५६, ४; **९.** १०८, ४.

अपऽऊर्णुवंतः **१.** १९०, ६; **४.** ४५, २.

अपः **१.** ११०, १; **२.** १४, ११; १७, ५; २२, ४; ३२, ४; ३८, ६; **४.** ३३, ९; **५.** ७९, ९; **६.** २३, ५; ३०, ३; **७.** २०, १; ४०, ४; **१०.** ३५, १; ५३, ६; ८८, ६.

अपः **१.** १०, ८; २३, १८; ३२, १; ३६, ८; ५१, ११; ५२, ६; ८; १२; ५५, ६; ५६, ६; ५७, ६; ६४, १; ६; ८०, ३–५; ९१, २२; ९६, २; १००, १८; १०३, २; ५; १०५,

११; १२२, ९; १३१, ४[२]; १५१, ४; १५७, ५; १६१, ११; १६४, ४७; १६५, ८; १७४, २; ९; १८०, ४; ५; **२.** ११, ५; १३, १; १४, २; २०, ७; २२, ४; २७, १३; ३६, १; **३.** ६, ७; ९, २; ३१, १६; ३२, ५; ६; ३४, ८; **४.** १६, ६–८; २६, २; २८, १; ३८, १०; ४२, ४; **५.** २, ११; १४, ४; २९, २; ३०, ५; ६; ३१, ६; ८; ४१, १४; ४६, ३; ४८, १; ८३, ६; **६.** २०, २; २२, ८; २८, ७; ३०, ४; ५; ३२, ५; ३९, ५; ४७, १४; ५७, ४; ६०, २[२]; ११; ६२, २; ६४, ४; ६८, ८; ७२, ३; ७३, ३; **७.** ९, ५; २१, ३; ३२, २७; ४४, १; ५६, २४; ६५, ३; ६८, ८; ९५, १; **८.** ३, १०; ६, १३; १६; ७, २२; २८; १२, ३; १५, २; ६; २६, २५; ३२, २; ४०, १०; ११; ७६, ३; ८३, ३; ९६, १८; ९७, १५; **९.** २, ३; ३, ६; ७, २; १६, २; ४२, १; ६१, २२; ६२, २६; ६३, ७; ६८, ४; ७०, २; ७८, १; ८५, ४; ८६, ४०; ९०, ४; ९१, ६; ९४, १; ९६, ३; १३; ९९, ७; १०७, ४; १८; १०९, २१; २२; **१०.** ९, ५; १६, ३; ३०, १–५; १०; ३६, १[२]; ४३, ८; ५१, १; ५८, ७; ६१, १६; ६४, ८; ६५, ७; ११; ६६, ८; ७६, ३; ८९, ४; ९५, १०; ९८, ५; १०४, ९; ११३, ६; १२१, ९; १२४, ७; १३८, १; १४७, १; १७८, ३.

अपःऽतमः १. १६०, ४; **१०.** ५३, ९; ११५, २.

अपःऽतमा ६. ६१, १३; **१०.** ७५, ७.

अपऽकामं ६. ७५, २.

अपऽगूर्य ५. ३२, ६.

अपऽगूळ्हं १. २३, १४; ११६, ११; **४.** ५, ३; **१०.** ३२, ६; ८८, २.

अपऽगूळ्हा १. १२३, ६.

अपऽगोह्ं २. १५, ७.

अपऽघ्नन् ९. ६१, २५; ६३, २४; २९; ९६, २३.

अपऽघ्नंतः ९. १३, ९; ६३, ५.

अपचत् ५. २९, ७.

अपचंत १. १६४, ४३; **१०.** २७, १७.

अपऽचितिं ४. २८, ४.

अपऽच्युवं १. २८, ३.

अपऽजर्गुराणः ५. २९, ४.

अपऽजंघनत् ९. ४९, ५.

अपऽतस्थुषः ९. १९, ६.

अपतिऽघ्नी १०. ८५, ४४.

अपत्यत १०. ११३, ५; ७.

अपत्यं १. १७४, ६; १७९, ६; **८.** ४९, ८; **९.** १०, ८.

अपत्यऽसाचं १. ११७, २३; **२.** ३०, ११; **६.** ७२, ५.

अपत्याय ७. ५, ७.

अपत्ये १. ६८, ४.

अपदी १०. २२, १४.

अपदी इति १. १८५, २.

अपदुःऽपदा १०. ९९, ३.

अपदे १. २४, ८.

अपद्रन् ६. २०, ४.

अपऽधा २. १२, ३.

अपऽपित्वं ३. ५३, २४.

अपसत् १. १९१, ९.

अपसन् १. ९२, २; १२४, १२; **६.** ६४, २; **७.** ५९, ७.

अपऽप्रोथंतः ९. ९८, ११.

अपऽबाधमानः १०. १०३, ४.

अपऽभर्तवै १०. १४, २.

अपऽभर्ता २. ३३, ७.

अपमर्त्य १०. ३९, ३.

अपऽम्लुक्तं १०. ५२, ४.

अपरः १. ७४, ८; १२०, २; **६.** २७, ५; **१०.** १८, ४; ५; २७, ७; १३६, ५.

अपरं १. ३१, ४; १४५, २; **६.** ४७, १५; **१०.** १३९, २.

अपरं १. ३६, ६; १८४, १; १८९, ४; **२.** २८, ८; २९, २; **८.** २७, १४; **१०.** ८६, ११.

अपरस्याः १०. २९, २.

अपरा १. १२४, ९; १८५, १.

अपराः ३. ५५, ५; **५.** ४८, २.

अपराऽजितं १. ११, २; **५.** २५, ६; **१०.** ४८, ११.

अपराऽजिता ३. १२, ४; **८.** ३८, २.

अपरान् ७. ६, ३.

अपराय ७. २०, ७.

अपराय ६. ३३, ५.

अपरासः ५. ४२, ६.

अपरिऽह्वृतः ५. २९, १४.

अपरिऽह्वृतं ८. २४, ९.

अपरिऽह्वृताः १. १००, ३.

अपरिऽह्वृतासः १. ८९, १.

अपरिऽविष्टं २. १३, ८.

अपरिऽवृतः २. १०, ३.

अपरिऽह्वृतः १०. ६, २.

अपरिऽह्वृता ८. ७८, ८.

अपरिऽह्वृताः १. १००, १९; १०२, ११; **१०.** ६३, ५.

अपरीभ्यः १. ३२, १३.

अपरीषु १. ११३, ११; **१०.** ११७, ३; १८३, ३.

अपरे १०. ४४, ७.

अपरेण २. २९, ३.

अपरेभिः ६. ४७, १७.

अपर्वन् ४. १९, ३.

अपलाशः १०. २७, १४.

अपऽवृक्ता १. २४, ८.

अपवथाः ९. ९६, १२.

अपऽवर्ता ४. २०, ८.

अपऽवार्ति १. १६२, १०.

अपवीरवान् १०. ६०, ३.

अपऽवृतं १. ५७, १.

अपऽवृतिं ८. ६६, ३.

अपऽव्रतान् १. ५१, ९; **५.** ४२, ९.

अपऽव्रतेन ५. ४०, ६.

अपश्चात्ऽदघ्वने ६. ४२, १.

अपश्यः १. ३२, १४.

अपश्यत् १. १६४, ९; २५; **३.** २६, ८; ४८, ३; **५.** ३०, १; **१०.** ५१, १; ६८, ८; ११३, ४; १३९, ४.

अपश्यतां ७. ३३, १०.

अपश्यन् १. ११३, ११; **१०.** १३५, ३.

अपश्यन् १. १६८, ९; **१०.** ८८, ११.

अपश्यंत १. १४६, ४.

अपश्यं १. १८, ९; १६४, ३१; ३. ३८, ६; ४. १८, १३; ५. २, २; १०. २७, १९; ७९, १; १८३, १.

अपश्यं १. १६३, ५–७; १६४, १; ४३; ५. २, ३; ४; ६२, १; ८. ५९, ६; ९६, १४; १०. २७, ८; ११४, ४.

अपश्याः १. १४८, ५.

अपश्याम १. १३९, २.

अपऽश्रितः ५. ६१, १९; ८. २४, ३०.

अपऽश्रितं १. ८४, १४.

अपसः ३. १२, ७; ६. ६९, १.

अपसः १. ७१, ३; ९२, ३; २. २८, ५; ३. २, ७; ८, ५; ६०, ३; ४. ३३, १; ५. ४२, १२; ६. १७, १२; ८. २, १७; ९. ७२, ६; १०७, १३.

अपसं १. २, ९.

अपसा १. ५४, ८; ४. २, १४.

अपसा १. ३१, ८.

अपसाःऽइव ६. ६७, ३; १०. १०६, १.

अपसां १. ९५, ४; १६०, ४; ३. २, ५; ६. ६१, १३; १०. ५३, ९; ७५, ७.

अपसि ३. १, ३; ११.

अपऽसु ८. ४, १४.

अपऽसेधन् १. ३५, १०; ९. ८२, २.

अपऽस्पृण्वते ८. २, ५.

अपस्पृधेथां ६. ६९, ८.

अपऽस्फुरं ८. ६९, १०.

अपस्यं १०. ८९, २.

अपस्यया ५. ४४, ८.

अपस्यवः ९. १४, २.

अपस्यात् १. १२१, ७.

अपस्यां ७. ४५, २.

अपस्युऽभिः ९. ७६, २.

अपस्युवः १. ७९, १; ९. २, ७; ३८, ३; ५६, २; १०. १५३, १.

अपऽह्नुवे १. १३८, ४.

अपा ८. ४, ३.

अपांसि १. ६८, ३; ७०, ४; ८५, ९; १७४, ३; २. ३, ६; १७, ८; ३. ३, ३; ४. १९, १०; ५. ४७, ६; ७. २१, ४; ६३, ४; ८. ९६, १९; २१.

अपाः ३. ५३, ६; ५. २९, ८; ६. ३९, १; १०. ९६, १३.

अपाक् ३. ५३, ११; ८. ४, १; १०, ५; १०. ४४, ७.

अपाकः ६. ११, ४.

अपाकऽचक्षसः ८. ७५, ७.

अपाका १. १२९, १.

अपाकाः १. ११०, २.

अपाकात् ८. २, ३५.

अपाके ६. १२, २.

अपाक्तात् ७. १०४, १९.

अपाङ् १. १६४, ३८.

अपाचः १०. १३१, १.

अपाचीः ५. ४८, २.

अपाचीनं ७. ७८, ३.

अपाचीनैः ७. ६, ४.

अपाचीं १०. ६७, ५.

अपाच्याः ८. २८, ३.

अपात् २. ३७, ४; ६. २८, १; ८. ६९, ११[२]; ९२, ४.

अपात् १. ३२, ७; १५२, ३; ४. १, ११; ६. ५९, ६.

अपादः १०. ९९, ४.

अपादं ३. ३०, ८; ५. ३२, ८.

अपादयत् २. ११, १०.

अपां १०. ३०, ४; ११९, १; १४९, २.

अपां १. २२, ६; २३, १९; ३२, ११; ४६, ४; ५१, ४; ५४, १०; ५६, ५; ६१, १२; ६७, ५; ७०, २; ८५, ९; १००, ११; १२२, ३; ४; १३४, ५; १४३, १; १४४, २; १४९, ४; १५८, ६; १६४, ५२; १६८, २; १८१, १; १८६, ५; १८७, ८; २. ४, २; १२, ७; १७, ५; १९, ३; २३, १८; ३०, १; ३१, ६; ३५, १–३; ७; ९–११; १३; ३. १, ५; १२; १३; ५, ३; ९, १; २५, ५; ४५, २; ४. २१, ८; ४०, १; ५८, ११; ५. ४१, १०; ४६, ७; ६. ८, ४; १३, १; ३; १७, १२; ४४, १८; ४७, २७; ५०, १३; ५२, १४; १५; ६४, १; ७. ९, ३; ३४, १५; ३५, १३; ४७, २; ८२, ३; ८८, ३; ८९, ४; १०१, २; १०३, ४; ८. १४, १०; १३; १६, २; १८, १६; १९, ४; २५, १४; ४४, १६; ९३, २२; ९. ३३, १; ४९, १; ७२, ७; ७४, ३; ७६, ५; ८६, ८; २५; ३६; ९६, १९; ९७, ४१; ५७; १०८, १०; १०९, १३; १०. ८, १; ५; १७, १४; ३०, ३; १४; ३६, ८; ४५, ३; ४६, १; ४९, २; ५१, ८; ७७, ४; ८९, १०; ९२, १३; ९३, ५; ९८, १२; १२३, १; १२४, ९; १४२, ७; १६८, ३.

अपाम ८. ४८, ३.

अपांऽइव १. ५७, १; ९. ९५, ३; १०८, ५.

अपायि १. १७५, १; २. १९, १.

अपायि ६. ४४, ८; १६.

अपारः ५. ८७, ६; ८. ६, २६.

अपारं ४. १७, ८.

अपारयत् २. १५, ५; ४. ३०, १७.

अपारां ३. ३०, ९.

अपारे ३. १, १४.

अपारे इति ३. ३०, ५; ४. ४२, ६; ९. ६८, ३.

अपारेण १०. ४४, १.

अपालां ८. ९१, ७.

अपाविपुः ९. ६०, २.

अपाष्ठऽवत् १०. ८५, ३४.

अपि १. १२१, १३; १२८, २; १४०, ७; १५८, ५; १६२, २; ८; ९; १४; १६४, ६; १७९, १; १८६, १; २. ३, ९; ५, ८; ११, १२; ३४, १०; ३. १, २१; ८, ९; ३३, २; ८; ३८, ६; ५. ३१, ९; ३३, १०; ४६, ७; ६. ३६, २; ५१, १६; ५४, ४; ५९, ९; ६२, १०; ६८, ६; ७. ३, १०; १६, ८; २१, ५; २२, ५; ३१, ५; ३८, ३; ४७, ३; ५७, ४; ६०, ६; ८. १८, १९; १९, ८; ३१, ७; ३२, ७; ४०, ६; ४३, ७; ४४, २४; २८; ४५, १९; ४७, ८; ५६, ४; ६६, १३; ९१, १; ९७, १२; ९.

६९, १; ७१, ६; १०. २, ३; १२, ५; १३, ५; १९, ४; ५; २५, १; ४४, ४; ४८, ३; ५२, ३; ५६, ४; ७१, ५; ६; ७७, ७; ८६, ४; ८७, २; १६; ९५, १८; ९८, ११; १०४, १०; १२०, ३; १४२, १; १५४, १; ५; १६६, ३; १६७, ४.

अपिंऽइतेः १. १२१, १०.
अपिऽइत्यं २. ४३, २.
अपिंऽइव ३. ३८, ८; ७. १८, ६.
अपिऽऊहे ७. १०४, १४.
अपिऽएर्ति १०. ११५, १.
अपिंशत् १०. ११०, ९.
अपिंशत ३. ६०, २.
अपिंशत १. ११०, ८; १६१, ९.
अपिंशन् ४. ३३, ४.
अपिंशन् १०. ६८, ११.
अपिऽकक्षे ४. ४०, ४.
अपिऽकक्षेभिः १०. १३४, ७.
अपिऽकक्ष्यें १. ११७, २२.
अपिऽकर्णे ६. ४८, १६.
अपिऽजुर्वा २. ३१, ५.
अपितः ७. ८२, ३.
अपिधानंऽवंतं ५. २९, १२.
अपिऽधाना १. ५१, ४; १६२, १३.
अपिऽधीन् १. १२७, ७.
अपिंऽनद्धं १०. ६८, ८.
अपिन्वः २. ११, २.
अपिन्वः ९. ९७, ३१.
अपिन्वत् १. ६२, ६; १०. ९९, १.
अपिन्वत् ४. १९, ७.
अपिन्वत १०. ७२, ७.
अपिन्वत ३. ५५, १३; १०. ३१, ११.
अपिंन्वतं १. ११७, २०; ११८, ८; ७. ६८, ८; ८२, ३; १०. ३९, १३.
अपिन्वं ४. ४२, ४.
अपिंप्रत ५. ३४, २.
अपिऽप्राणीं १. १८६, ११.
अपिंबः ३. ३२, ९; ३६, ३; ५१, ७; ५. २९, ११; ६. ४०, २; ८. ५१, १; ५२, १; १०. १३१, ५; १३८, २.
अपिबः ३. ३२, १०; ४८, २; ४. ३५, ७; ८. ४, ४.
अपिंबत् ८. ४५, २६; ५२, ३; १०. १३६, ७.
अपिबत् १. ३२, ३; २. १५, १; २२, १; ३. ४८, ४; ४. १८, ३; ८. ७७, ४; १०. १०२, ४.
अपिऽयंतं १. १६२, २०.
अपिंऽरिप्राय १. ११८, ७; ८. ५, २३.
अपिऽवातयंतः १. १६५, १३.
अपिंऽवृतः १०. ३२, ८.
अपिंऽवृतं १. १२१, ४; २. ११, ५.
अपिऽशर्वरे ३. ९, ७; ८. १, २९.
अपिऽस्थितं १. १४५, ४.
अपिंऽहितं १. ३२, ११; ५. ६२, १; १०. १२९, ३.
अपिंहिताऽइव ४. २८, १.
अपिंऽहितानि ४. २८, ५.
अपीच्यः ८. ४१, ८.
अपीच्यं १. ८४, १५; २. ३५, ११; ८. २९, ६; ४७, १३; ९. ७१, ५; ७५, २; ८६, १०; ८७, ३.
अपीच्यौ ८. ४१, ५.
अपीच्यै १०. १२, ८.
अपीच्येन ७. ६०, १०; १०. ५३, ११.
अपीपतत् ८. १००, ७.
अपींपयत् १०. ६४, १६.
अपींपयंत ७. ३६, ३.
अपीपरन् ९. ७३, १.
अपीपेत् १०. ३१, ११.
अपींपेम ८. ६६, ७.
अपींप्यन् ८. ९९, १.
अपुः १. १६४, ७.
अपुनन् ३. २, ९.
अपुनरिर्ति १०. ६८, १०.
अपुंपोत् ३. २६, ८.
अपुंरुपऽघ्नः १. १३३, ६.
अपुरुषं १०. १५५, ३.
अपुष्पाः १०. ९७, १५.
अपुष्पां १०. ७१, ५.
अपूपं ३. ५२, ७; १०. ४५, ९.
अपूपऽवंतं ३. ५२, १.
अपूर्व्यं ८. २१, १; ८९, ५.
अपूंर्व्यः १. १३४, ६.
अपूंर्व्यं ३. १३, ५; ५. ५६, ५; ८. १८, १; १०. २३, ६.
अपृंर्ण्या १. ४६, १; ६. ३२, १; ८. ६६, ११.
अपृक्तु ९. ९७, १.
अपृच्छत १. १६१, ४; १३.
अपृंच्छं ५. ३०, ४.
अपृच्यंत १. ११०, ४.
अपृणः ३. ३, १०.
अपृणक् ४. १९, ७.
अपृणत् २. १५, २; २२, २; ३. २, ७; ३४, १.
अपृंणतः ५. ७, १०; ६. ४४, ११.
अपृंणन् १०. ११७, १.
अपृंणंतः ५. ४२, ९.
अपृंणंतं १. १२५, ७; १०. ११७, ७.
अपृणाः ३. ६, २; ७. १३, २.
अपृणात् ४. १८, ५; १०. ५५, ३.
अपृतन्यत् १. ३२, ७.
अपेशसे १. ६, ३.
अपो इर्ति २. २८, ६; ५. ४८, २; ७. ८१, १; ८. ६७, १५; १०. ८८, १२.
अप्ऽजाः ४. ४०, ५.
अप्ऽजां ७. ३४, १६.
अप्ऽजित् ९. ७८, ४.
अप्ऽजिते २. २१, १.
अप्ऽतुरः १. ३, ८; ११८, ४; २. २१, ५; ९. ६३, ५.
अप्ऽतुरं ३. २७, ११; ५१, २; ९. ६१, १३; ६३, २१; १०८, ७.
अप्ऽतूर्यं ३. १२, ८.
अप्ऽतूर्यें ३. ५१, ९.
अप्नयस्यं १. १२४, ५.
अप्नः १. ११३, ९; २०; १०. ३६, १३; १०६, ९.
अप्नःऽस्थः ६. ६७, ३.
अप्नऽराजौ १०. १३२, ७.
अप्नंवानः ४. ७, १.
अप्नवानऽवत् ८. १०२, ४.
अप्नंसः १०. ८०, २.
अप्नंस्वती १०. ४२, ३.
अप्नंस्वतीं १. ११२, २४.
अप्नंस्वतीषु १. १२७, ६.
अप्यः १. १४५, ५; ६. ६७, ९; ९. ८६, ४५.

अप्र्यं २. ३८, ७; ८; १०. ८६, १२.

अप्र्या १०. १०, ४; ११, २; ९५, १०.

अप्र्याः ३. ५६, ५; ६. ५०, ११; ७. ३५, ११; ९. १०८, ६.

अप्र्यानि ६. ४९, ६.

अप्र्येभिः ४. ५५, ६.

अप्रऽआयु ५. ८०, ३.

अप्रऽआयुवः १. ८९, १.

अप्रऽआयुषे १. १२७, ५.

अप्रऽक्रेतं १०. १२९, ३.

अप्रऽक्षितं १. ५५, ८.

अप्रऽचेतसः ९. ६४, २०; ९८, ११.

अप्रऽचेताः १. १२०, १; १०. ७, ६; ११७, ६.

अप्रऽच्युतानि २. २८, ८.

अप्रऽजज्ञयः १०. ७१, ९.

अप्रजाः १. २१, ५.

अप्रता ८. ३२, १६.

अप्रति १. ५३, ६; ६. ४४, १४; ७. २३, ३; ८३, ४; ९९, ५; ९. २३, ७.

अप्रतिऽइत १. १३३, ६.

अप्रतिऽइतः ३. ४६, ३; ४. ५०, ९; ५. ३२, ९; ६. २०, ९; ७३, ३; १०. १११, ३.

अप्रतिऽइतं १. ३३, २; ११७, ९; ४. ४२, ६; ५. ३२, ७; १०. १०४, ७.

अप्रतिऽइतस्य ५. ४२, ६.

अप्रतिः ५. ३२, ३.

अप्रतिधृष्टऽशवसं १. ८४, २.

अप्रतिऽमानं ८. ९६, १७.

अप्रतिऽस्कुतः १. ७, ६; ८; ८४, ७; १३; ५. ६१, १३; ७. ३२, ६.

अप्रतिऽस्कुतं ३. २, १४; ८. ९३, १२; ९७, १३.

अप्रतीनि २. १९, ४; ४. १७, १९; ६. ३१, ४; ७. ८५, ३; ८. ९०, ५.

अप्रयतं ६. ६९, ५; ७२, २.

अप्रयंत ७. ३३, ६.

अप्रयुयुः १. ६२, ५; ८. ८९, ५.

अप्रथयन् १०. ६२, ३.

अप्रयिष्ट २. ११, ७.

अप्रयेतां १०. ८२, १; १४९, २.

अप्रऽदुग्धाः ३. ५५, १६.

अप्रऽदूपितः १. १४५, २.

अप्रऽभुः ९. ७३, ९.

अप्रऽभूती १०. १२४, ७.

अप्रऽमूराः १. ९०, २.

अप्रऽमृष्यः ४. २, ५.

अप्रऽमृष्यं २. ३५, ६; ६. २०, ७; ३२, ५.

अप्रऽयुच्छतः १०. ६६, १३.

अप्रयुच्छत्ऽभिः १. १४३, ८.

अप्रऽयुच्छन् १. १०६, ७; १४३, ८; २. ९, २; ११, ८; ३. ५, ६; २०, २; ५. ८२, ८; १०. ४, ७; ७, ७; १२, ६; १७, ५; ८८, १६.

अप्रऽयुतां ७. १००, २.

अप्रयुत्वऽभिः ६. ४८, १०.

अप्रऽवीता ४. ७, ९.

अप्रऽवीताः ३. ५५, ५.

अप्रऽशस्ताः ४. २८, ४.

अप्रशस्ताःऽइव २. ४१, १६.

अप्रऽशस्तान् १. १६७, ८.

अप्रऽहनं ६. ४४, ४.

अप्रऽहितं ८. ९९, ७.

अप्राः १. ५२, १३; ११५, १; ४. १४, २; ५२, ५; ५३, ३; ९. ७२, ५; ९७, ३८; १०. १, १; ७४, ६; १०६, ११; १२७, २.

अप्राट् १०. ३२, ७.

अप्रामिऽसत्य ८. ६१, ४.

अप्रायुऽभिः ८. २४, १८.

अप्रियायत ३. ५३, ९.

अप्रीणात् ८. २३, १६.

अप्रोषिऽवान् ८. ६०, १९.

अप्वे १०. १०३, १२.

अप्सः १. १२४, ७; ५. ८०, ६; ८. ४५, ५.

अप्संत १. १००, ८.

अप्सरसः ७. ३३, ९; १२; ९. ७८ ३.

अप्सरसां १०. १३६, ६.

अप्सराः १०. १२३, ५.

अप्सवः ७. ४, ६.

अप्सवं १०. ६५, ३.

अप्साः ९. ६५, २०; ७१, ८; ८४, १.

अप्सां १. ९१, २१; ६. १४, ४.

अप्ऽसु १. २३, १९[२]; २०; ५९, ३; ६५, ५; ९१, ४; ९५, ३; १०४, ६; १०५, १; १०८, ११; १०९, ४; ११६, २४; ११७, ४; १३५, ६; १५१, १; १६३, ४; १८२, ६; १८४, ३; २. ११, ५; ३५, ४; ५; ७; ८; ३८, ७; ३. १, ३; ९, ४; १३, ४; २२, २; ४. १३, ४; ५. ४४, ६; ४५, ११; ८५, २; ६. १९, १२; २५, ४; २९, ५; ३१, १; ४६, ४; ६६, ८; ७. १८, १२; ७०, ४; १०३, ५; ८. १, १७; ९, ५; ४३, ९; ६८, ९; ८२, ८; ९. २, ५; १६, ३; २०, ६; २४, १; ३०, ५; ४२, १; ६२, ४; ५; ६५, २६; ७१, ३; ७९, ४; ८०, ५; ८५, १०; ८९, २; ९६, १०; २४; ९७, ४७; ४८; १०७, १; २; १०. १०, ४; २७, १७; ३०, ४; ३२, ६; ४५, १; ३; ५; ५०, २; ३; ५१, ३; ६३, १५; ६५, ९; ७३, ९; १०४, २; १२५, ७.

अप्सुऽक्षितः १. १३९, ११.

अप्सुऽजाः ८. ४३, २८.

अप्सुऽजित् ८. १३, २; ३६, १; ९. १०६, ३.

अप्सुऽसदे ३. ३, ५.

अफलाः १०. ९७, १५.

अफलां १०. ७१, ५.

अफाणयत् ८. ६९, १३.

अबधिरं ८. ४५, १७.

अबध्नन् १०. ९०, १५.

अबध्नात् १०. ८५, २४.

अबंधनः ३. ५५, ६.

अबंधवः ८. २१, ४.

अबंधुना १. ५३, ९.

अबलाः ५. ३०, ९.

अबाधत १०. ११३, ४; ५.

अबाधितः १०. ९२, ८.

अबाधेथां ४. २८, ४.

अबिभः १०. ६९, १०.

अबिभेत् १०. १३८, ५.

अबिभ्यत् ६. २३, २.

अबिभ्युषः १. ११, ५.

अबिभ्युषा १. ६, ७; ९. ५३, २.

अबिभ्रन् १०. २८, ८.

अबीभयंत १. ३९, ६.

अबुध्रे १. २४, ७.

अबुध्रेषु ८. ७७, ५.

अबुध्यं ४. १९, ३.

अबुध्यमानं ४. १९, ३.

अबुध्यमानाः १. १२४, १०; ४. ५१, ३.

अबुध्यमाने इति १. २९, ३.

अबुध्रन् ७. ७२, ३; ८०, १.

अबुध्रं १०. ३५, १.

अबुभोजीः १. ३३, ९.

अबूबुधत् १. १६१, १३.

अबोधयः १. १०३, ७; ५. ७९, १.

अबोधि १. १५७, १; ३. ५, १; ५. १, १; २; ७. ९, १.

अबोधि १. ९२, ११; १२३, २; ३. ५६, ४; ६१, ७; ७. ७३, ३; ८०, २.

अब्दुऽया ५. ५४, ३.

अब्दिद्ऽमान् ५. ४२, १४.

अब्रवं १. १०८, ६.

अब्रवं ६. ५५, ५; ८. ३, २४; २४, १४.

अब्रवीत् १. १६१, ५; १२.

अब्रवीत् १. २३, २०; १४५, ५; १६१, ९^{२}; १३; १९१, १६; ४. १८, ११; ८. ३३, १७; ४५, ३७; ७७, २; ९१, १.

अब्रवीत ४. ३५, ३.

अब्रवीतन १. १६१, ३.

अब्रवीतन १. १६१, ८; १२.

अब्रह्मता ५. ३३, ३.

अब्रह्मा ४. १६, ९; १०. १०५, ८.

अब्रह्माणः ७. २६, १.

अब्रुवन् १. १६१, २; ९. १०१, ५; १०. २४, ५.

अभक्त ३. ३३, १२; ९. १०२, २.

अभक्तं १. १२७, ५; ३. ३०, ७.

अभक्ते १०. ११२, १०.

अभक्षयं १०. १६७, ३.

अभक्षि ४. ३१, ५.

अभक्षि ८. ४८, १.

अभजः ३. ३५, ९; ४७, ३.

अभजत् १. १५६, ५; २. २४, १४; ३८, १; ४. ३०, १६.

अभजंत १. २०, ८.

अभजंत १. ९१, १.

अभयऽतमेन १०. १७, ५.

अभयंत ५. ३०, ५.

अभयं २. २७, ११; १४; ४१, १२; ३. ४७, २; ४. २९, ३; ६. २८, ४; ४७, ८; १२; ७. ७७, ४; ८. ६१, १३; ९. ७८, ५; १०. ६३, ७.

अभयंऽकरः १०. १५२, २.

अभयानां १०. ९२, १४.

अभयानि ९. ९०, ४.

अभये ३. ३०, ५.

अभरः ८. ९७, १.

अभरत् ८. ८२, ९; ९. ६८, ६; १०. १४४, ४; ५.

अभरत् १. १६१, १०; ३. ५३, १६; ४. २६, ७; ६. ८, ४; ८. ७७, १०; १००, ८; ९. ७२, ३; ८६, २४; ११३, ३; १०. ११, ४; १७, २; ७२, ९; १०२, ४; ११३, ५.

अभरन् ४. ३३, ४.

अभरन् १०. १८१, ३.

अभरंत १०. ९२, १०.

अभरं १०. ६०, १०.

अभरिष्यत् २. ३०, २.

अभवः ३. ३, १०; ९, २; ६. १, १; ८. ७६, ११; ९३, १७; १०. ७०, ९.

अभवः १. ४, ८; ३१, १; ३२, १२; ५१, १३; ७२, ७; ९१, २; २. १३, ९; १०; ३. १, १७; ६, ५; ३२, १०; ४. १७, ६; ६. ५, ३; ३०, ५; ३६, १; ८. ९६, १६; ९. ५९, ४; ८६, २३; १०७, ६; ७; १०. ८, ४; ८८, ५; १११, ६; १५३, ५.

अभवत् १. ५८, १; ११२, ४; १४६, ५; ७. १०, ५; ३३, ६; १०. ३१, ६; ६१, ६; ९२, १५; १३५, ५; ६; १५९, ४.

अभवत् १. ३२, ९; ५९, २; १४१, ४; १४३, २; १४६, ४; २. ५, ३; १३, १; २२, २; २४, १४; ३. २, २; ८; २९, ११; ३१, ४; ७; ३४, १०; ४. ३, ११; ३३, ९; ३६, ३; ५. ११, ३; ४; ६. १८, २; ६; २०, ३; ४४, ७; ५७, ४; ६५, ५; ७. ८३, ४; ९८, ५; १०४, २१; ८. ७७, ३; ८९, २; ९. ८६, २१; १०. ४५, ८; ८५, ९; ८८, २; ८; ९०, ४; ९६, ४; ११०, ११; ११३, २; १३०, ४; १४९, ३; १५०, ४.

अभवत ४. ३५, ८^{२}.

अभवतं १. ११७, १४.

अभवन् ३. ३५, ९.

अभवन् १. ११९, ८; ४. १७, ६; ७. ८३, ७.

अभवं ४. २६, १.

अभाजः १०. ८३, ५.

अभारित्वभाः १०. २०, १०.

अभार्षं १०. १३७, ४.

अभि १. ५, १; १०; १०, ४^{२}; ११, २; ८; १५, ३; १९, ९; २२, ११; २४, ३; २५, ११; ३१, १८; ३३, ९; ११; १३; ३५, ९; ३७, १; ४२, ४; ८; १०; ४५, ८; ४८, ७; १४; ५१, १^{२}; २; १०; ५२, ५; ५४, २; १०; ६१, १०; ७१, ७; १०; ७४, ८; ७८, १^{२}; २–५; ८०, ३; १२; ८४, ४; ८६, ५; ८९, २; ९१, २३; ९२, १०; ९४, ८; ९५, १०; १००, १७; १०१, ६; ७; १०५, १९; १०८, १; ६; ११०, ७; ११५, २; ११७, २१; ११८, ४; ११९, १; १२०, ८; १२१, ६; ८८; १२३, ७; १२४, ९; १२५, ७; १३४, १; १३५, ४; ६; १३६, ५; १३९, ३; ८; १४०, २; ३; ५; ६; १३; १४४, १; २; १४५, ४; १४६, २;

३; १४९, ४; १५४, ५; १५६, २;
१६०, २; १६२, ११; १५; १६४,
३; २०; २७; २८; ४४; १६६, १४;
१७०, १; १७४, ५; १७८, ४; ५;
१७९, ३^{२}; १८३, २; १८९, ३; १९०,
४; ६; **२.** २, २; ४, २; ७; ९;
८, ४; ६; ९, ४; १४, ९; १५,
५; १६, ८; १७, ४^{२}; २०, २;
२२, २; ४; २३, ६; ९; १६; २४,
४; ६; २५, ३; २६, १; २७, १४;
२८, १; ३; २९, २; ३१, २; ३३,
१; ७; ३४, ९; ३९, ७; ४१, १०;
४३, १; **३.** १, ४; १६; ४, ५;
६, १०; ११, ७; १४, ४; १५, ५;
१६, २; ४; २३, २; २९, १३;
३०, ८; ११; ३१, ४; ५; १०;
३२, १५; ३८, १^{२}; ४०, ७; ४४,
२; ४६, ४; ४८, ३; ५१, १;
४; ५३, १७; १९; ५४,
६; ५५, ९; ५९, १; ७^{२};
६०, १; ६२, ९; **४.** १, ३;
८; १३; १४; १६; ४, ६; ९;
५, ७; ६, १; ७, ४; १२, १; १६,
५; १९; १९, ५; २०, ५; २१, २;
२३, १; ४^{२}; २४, ८; २७, २;
३०, १३; ३१, ३; ४; ३२, ४;
३३, ९; ३८, ८; ४३, ५; ४४, २;
४६, ३; ५०, २; ७; ५३, ४; ५;
५६, ५; ५७, ८; ५८, ५; ८; ९^{२};
१०; **५.** ३, ७; ९; ४, १^{२}; ५, ४;
७, ५; ८, ७; ९, ७; १५, २; १९,
१; २३, १; २७, ३; २८, ३;
२९, २; १२; ३१, २; ५; ३३,
२; ३; ३७, ५; ४१, ८; १९; ४२,
३; ४४, ५; ५१, ५–७; ५४, १५;
६०, ४; ६५, ३; ७९, ४; ८३, ७;
८६, २; **६.** ५, ७; ७, २; ४; ९,
५; १०, ५; १३, ६; १५, १२;
१५; १६, ४४; १७, १–३; ८; ९;
१८, ९; १३; १९, ३; ९;
२०, १; २१, ७^{२}; १०; १२; २२,
१; २; २५, ५; २८, ४; ३१, ३;
३४, ३; ४; ३६, ५; ३७, ३; ३८,
३; ३९, २; ४४, १७; ४५, १८;
२५; ४७, २५; ४८, १९; ४९, ८;
१४; १५^{२}; ५०, ६; १५; ५१, २;
५२, २; ५३, २; ६०, २; ७;
६१, १४; ६३, ७; ७१, १; **७.**
१, १०; १३; ५, २; ७; ८, ४;
१५, २; १८, २; १०; १६; २१,
६; २३, ६; २५, २; ३१, ४;
३२, २२; २४; ३३, १; ९; ३४,
५; ९; ३५, ४; ३६, ६; ३७, १;
७; ३८, ४^{२}; ५; ३९, ४; ४८, २;
३; ५६, ३; २४; ५९, ४;
८; ६०, २; ६१, १; ६७, ३; ६९,
२; ७०, ५; ७१, ४; ७२, १; ८३,
५; ९; ८६, २; ८८, २; ९०, ५;
९३, ८; १०३, २; ३; १०४, २;
१९; २१^{२}; २३; **८.** १, २७; ३२;
२, १९; ४०; ३, ३; ५, ३४; ६,
७; २५; ३४; ४२; ८, १२; १२,
१५; २३; १३, २७; २८^{२}; १५, १;
१७, ७; १५; २०, १६; १९; २१,
५; १२; १६; २३, २६^{२}; २४,
१९; २१; २५, ७; २१; २७, ६;
३१, १५; ३२, १३; २८; २९;
३७, २; ४०, ४; ४५, २२; ४६,
१४; ४७, १; ७; ४८, १; ४९, १;
५०, ३; ५१, ८; ५५, १; ५९,
३; ६; ६०, ४; ६६, १०; ६७, ५;
९; ६९, ४; ५; ११; ७२, २; ७४,
१४; ७५, १५; ७७, ५; ७९, २;
८१, ५; ६; ८८, १; ४; ८९, ४;
९२, ६; ३१; ९३, १; ४; १९;
२१; ९५, १; ९६, १५; ९८, ५;
९९, ५; १००, १; ३; ४; १०१,
६; १०२, ३; ९; १०३, ५; **९.**
१, २; ४^{२}; ९; ३, १; ४, ७; ८;
९, २^{२}; ३^{२}; ७, ३; ५; ८, १; ९,
५; ६; १०, ९; ११, १; २; ६;
१२, २; ८; १३, २; ७; १४, ७;
१६, ९; १७, २; ६; २०, १; ४;
२१, ३; २३, १; ४^{२}; २४, २;
२५, २; २६, २; २८, ४; ३०, ४;
३२, ५; ३३, २; ५; ३४; ५; ३५,
३^{२}; ३६, २; ३७, २; ६; ३८, ६;
४०, १; ४२, ५^{२}; ४४, १; ४५,
२; ४७, १; ४८, ३; ५१, ५^{४};
५६, ३; ५७, २; ५९, ४; ६०, ३;
६२, १; ३; १९; २३; २५; २८;
६३, ६; १२^{२}; २५; २९; ६४, ८;
१३; २१; ६५, १९; ६६, १; ४;
२२; ६७, ३; ९; १४; ६८, २; ८;
७०, १०; ७१, ७; ७२, ३; ७३,
३; ८; ७४, ७; ७५, १; ५; ७७,
१; ४; ७८, १; ३; ७९, ३; ८०,
२; ३; ८२, १–३; ८४, ५; ८५,
२–४; ७; ८; ८६, २; ३; १४;
१५; १७^{२}; २५; ३५; ३६; ४३; ८७,
१; ५–७; ८८, ६; ८९, ७; ९०,
२; ९३, २; ३; ९४, २; ५; ९६,
८; १६^{४}; २२; ९७, ३; ४; ७;
१२; २१; २५; ३९^{२}; ४३; ४५;
४९^{४}; ५०^{४}; ५१^{४}; ९८, १; २; ९९,
२; ४; १००, १; १०१, ३; ९; १६;
१०२, ७; १०३, ३; १०४, २;
४^{२}; १०५, १; १०६, ११; १२;
१०७, १४; २१; २३; २५; १०८,
२; ६; ९; ११०, २; ६; ८; ९; ११४,
३; ४; **१०.** १, ३^{२}; ३, २; ३^{२};
४, २; ६; ५, ६; ७, २; ८, ८;
९, ४; १५, ६; १६, १; १७, ६;
१८, ८^{२}; ११; २२, ८; २३, ४;
२५, ३; २६, ३; २७, ११; २८,
८; २९, ३; ७; ३१, ३; ३२, १;
४^{२}; ३४, १४; ३७, १२; ४३, ७;
४५, ९; ४७, ८; ४८, ७^{२}; ४९,
११; ५०, २; ५३, २; ४; ७; ८;
११; ५९, ३; ६०, ६; ६३, १६;
६४, १; ३; ६५, १५; ६६, ९;
६८, १; ११; ६९, ६; १२; ७१,
३; ७४, ४; ७५, २; ४; ८३, ३;
६; ७; ८४, १, ८६, ८; ९; १९;
८७, ३; ९; १४; ८९, १५^{२}; ९०,
४; ९२, १३; १५; ९४, २; ९६,
२; ९८, २; ५; ९९, ३; ११;
१०३, ७; १२; १०७, ४; ११३,
४; ११५, ७; ११७, ७; ८; ११९,

…; १२०, ३; १२१, ६; १२३, २; ३; ६; ८; १३२, १[२]; २; ३; १३४, ७; १३५, २; १३६, ३; १३९, २; ३; ५; १४५, ६; १४८, ३; १४९, ४; १५९, १; १६९, १; १७३, ६; १७४, १; २[३]; ३[३]; १८०, ३; १९१, ३.

अभिऽअंजनं ८. २, २४; ७८, २; १०. ८५, ७.

अभिऽअभि ९. ११०, ५.

अभिऽअर्षन् ९. १०६, १३.

अभिऽआयंसेन्यां १. ३४, १.

अभिऽआरे ८. ७२, ११.

अभिऽआवर्तिने ६. २७, ५.

अभिऽआवर्ती ६. २७, ८.

अभिऽईतिं ७. २१, ९.

अभिऽइतीः २. २३, ३.

अभिऽइत्य ४. ३२, १०; ९. ५५, ४; १०. ९९, ५.

अभिऽइद्धः १. १६४, २६.

अभिऽउंदतः ९. ६१, ४.

अभिऽउप्य २. १५, ९.

अभिऽऊर्णुवाना ५. ४१, १९.

अभिऽकनिक्रदत् ९. ९७, १३; १०. ६७, ३.

अभिऽक्रतूनां ३. ३४, १०.

अभिऽक्रंदन् ९. ८६, ११; १०. २१, ८.

अभिऽक्रम्य १. ८०, ५.

अभिऽक्षत्तारः २. २९, २.

अभिऽक्षत्तुः ७. २१, ८.

अभिऽक्षदां ६. ५०, १.

अभिऽक्षरंति ९. ६१, ५.

अभिऽक्षिपन् ५. ८३, ३.

अभिऽख्या १. १४८, ५; ८. २३, ५; १०. ११२, १०.

अभिऽख्याता ४. १७, १७.

अभिऽख्याय १. १५५, ५; २. ३०, ९.

अभिऽगच्छंति १०. १४६, ५.

अभिऽगीतः ९. ९६, २३.

अभिऽगूर्ते १. १६२, १५.

अभिगूर्तिः १. १६२, ६; १२.

अभिऽगूर्ये २. ३७, ३.

अभिऽगृणाति १. ५४, ७.

अभिऽचक्षाणः २. ४०, ५.

अभिऽचक्षे १. १०२, २; ११५, ५; ५. ३१, १२.

अभिऽचक्ष्य १. ९२, ९; ८. १, ३४.

अभिऽचक्ष्ये ८. ४, ७.

अभिऽचष्टे ७. १०४, ८; १०. ८५, १८.

अभिऽजायंत १. १६८, २.

अभिजिघ्रंती इत्यभिऽजिघ्रंती १. १८५, ५.

अभिऽज्ञु १. ३७, १०; ७२, ५; ३. ३९, ५; ७. २, ४; ८. ९२, ३.

अभितः १. ५३, ३; ८३, १; १०५, ८; १८२, ४; २. १३, ७; ४. १, १४; ५०, ३; ५. १५, ३; ३०, १०; ७. ५५, ५; ५९, ७; ९८, ६; ९९, ३; १०१, ४; १०३, ७; ८. ५, ३८; १०१, १४; ९. १०१, ११; १०. २७, ८; ५३, ७; ७६, ६; ८१, ६; १३३, ४; १३४, ५.

अभिऽत्सरंति ८. २, ६.

अभिऽदासत् ६. ५, ४.

अभिऽदासतः १०. १०२, ३; १५२, ३.

अभिऽदासति १. ७९, ११; ७. १०४, ७; १०. ९७, २३; १३३, ५; १५२, ४.

अभिऽदिप्सुः २. २३, १०.

अभिऽदिप्स्वः २. २३, १३.

अभिऽदुद्रोह १. २३, २२.

अभिऽद्यवः १. ४७, ४; १२७, ७; १३४, २[२]; ३. २७, १; ६. ५१, १५; ८. ७, २५; १०. ७७, ३; ७८, ४.

अभिऽद्यवे ८. ७५, ६.

अभिद्युऽभिः १. ६, ८; ५३, ५; ८. ४, २०.

अभिऽद्यु १. ११९, १०.

अभिऽद्रुहे २. २७, १६.

अभिऽद्रोहं ७. ८९, ५; १०. १६४, ४.

अभिऽधित्संते १०. ८५, ३०.

अभिऽध्रुक् १. १२२, ९.

अभिऽनक्षतः २. २४, ६; ८. ९६, ५.

अभिऽनक्षमाणाः १०. १७, ९.

अभिनत् १. ५२, १०; १०३, २; २. २४, ३; ८. १४, ७.

अभिनत् १. ३२, १; ३३, १२; ५३, ८; २. ११, २; ४. १९, ४; ८. ७६, २; १०. ८, ९; ४५, ६; ६७, १२; ६९, ११; ९९, ७.

अभिऽनभ्यं १०. ११९, १२.

अभिऽनेता ४. २०, ८.

अभिऽदन् १०. ६२, २.

अभिन्ने ६. २८, २.

अभिऽपद्य १०. ७१, ९.

अभिऽपश्यंती ७. ७५, ४.

अभिऽपासि ३. ९, ६.

अभिऽपित्वं ४. १६, १; ७. १८, ९; १०. ४०, २.

अभिऽपित्वे १. १२६, ३; १८६, १; ६; १८९, ७; ४. ३४, ५; ३५, ६; ५. ७६, २; ८. ४, २१; २७, २०.

अभिऽपित्वेषु १. ८३, ६.

अभिऽप्रघ्नंति ६. ४६, १०.

अभिऽप्रचक्षे १. ११३, ६.

अभिऽप्रभंगिनः ८. ४५, ३५.

अभिऽप्रमंदुः ८. १२, १३.

अभिऽप्रमुरा १०. ११५, २.

अभिऽप्रियः ९. ३१, ३.

अभिऽप्रिये १. १६२, ३.

अभिऽभंगाय २. २१, २.

अभिऽभंजतीनां १०. १०३, ८.

अभिऽभा २. ४२, १.

अभिऽभुवे २. २१, २.

अभिऽभूः १. १००, १०; ८. ८९, ६; ९७, ९; ९८, २; १०. १५३, ५; १६६, ४.

अभिऽभूतरं ८. ९७, १०.

अभिऽभूति ४. २१, १; ४१, ४; १०. ७६, २.

अभिभूतिऽओजसं १. ५२, ७.

अभिभूतिऽओजाः ३. ३४, ६; ४८, ४; ४. ४२, ५; ६. १८, १; १०. ८३, ४.

अभिऽभूतिः ८. १६, ८.

अभिऽभूतिं १. ११८, ९; ४. ३८, १; ९.

अभिऽभूते १. ५३, ३; ६. १९, ६; १०. ८४, ६; १२१, १.

अभिऽभूयं ३. ४८, ४.
अभिऽभूवरी १०. १५९, ५; ६.
अभिऽमातयः १. २५, १४.
अभिऽमातये ८. ३, २.
अभिऽमाति ५. २३, ४.
अभिऽमातिः १०. ६९, ५.
अभिऽमातिनं १. ८५, ३.
अभिऽमातिं ८. २५, १५; १०. ८४, ३; १०२, ४.
अभिऽमातिषु ३. ३७, ७.
अभिमातिऽसहः १. ९१, १८; २. ४, ९; ६. ७, ३; ६९, ४.
अभिमातिऽसहः १०. ८३, ४.
अभिमातिऽसहं १०. ४७, ३; १०४, ७.
अभिमातिऽसहं १०. १२८, ७.
अभिमातिऽसहो ३. ३७, ३.
अभिमातिऽहनं ३. ५१, ३.
अभिमातिऽहा ९. ६५, १५.
अभिऽमातीः ३. २४, १; ६२, १५; ८. २४, २६; १०. १८, ९; ११६, ६.
अभिऽमृशे २. १०, ५.
अभिऽयुग्वना ६. ४५, १५.
अभिऽयुजः ३. ११, ६; ४. ३८, ८; ५. ४, ५; ६. २५, २; ८. ४५, ८; ९. २१, २.
अभिऽयुध्यः ७. ९८, ४.
अभिऽरक्षति १०. १७०, १.
अभिऽरक्षति १. १६३, ५.
अभिऽरक्षमाणाः १०. १५७, ४.
अभिऽरक्षसि १०. ८६, ४.
अभिऽराष्ट्रः १०. १७४, ५.
अभिऽवयसः १०. १६०, १.
अभिऽवर्तः १०. १७४, ३.
अभिऽवर्तेन १०. १७४, १.
अभिऽववृते १०. १७४, १.
अभिऽवीता ७. २७, ४.
अभिऽवीरः १०. १०३, ५.
अभिऽवृतः ८. ३९, ५; १००, ९; १०. १७६, ३.
अभिऽवृतं १. ३५, ४; ३. ४४, ५.
अभिऽवृता १. १६४, २९.
अभिवृताऽइव १०. ७३, २.
अभिवृते इत्यभिऽवृते ६. ७०, ४.

अभिऽवृत्य १०. १७४, २.
अभिऽवृष्टः ७. १०३, ४.
अभिऽवेगः १०. २७, १.
अभिव्रजत्ऽभिः १. १४४, ५.
अभिऽव्रजन् १. ५८, ५; ९. ६८, ३.
अभिऽव्लग्य १. १३३, १; २.
अभिऽव्लङ्गैः १. १३३, ४.
अभिऽशसा १०. १६४, ३.
अभिऽशस्तये ५. ३, १२; ७. ९४, ३; ८. १९, २६.
अभिशस्तिऽचातनः ३. ३, ६.
अभिशस्तिऽपाः ९. २३, ५; ९६, १०.
अभिशस्तिऽपां ६. ५२, ३.
अभिशस्तिऽपावा १. ७६, ३; ७. ११, ३.
अभिऽशस्तिं ३. ३०, १; ५. ३, ७.
अभिऽशस्तीः ८. ८९, २.
अभिऽशस्तेः १. ७१, १०; ९१, १५; ९३, ५; ६. ४२, ४; ७. १३, २; ८. ६६, १४; १०. ३०, ७; ३९, ६; १०४, ९.
अभिऽशासति ६. ५४, २.
अभिऽश्नथः १०. १३८, ५.
अभिऽश्रावय १. १८५, १०.
अभिऽश्रावे १०. १२, १.
अभिऽश्रियः ९. ७९, ५; ८६, २७; १०. ६६, ८.
अभिऽश्रियं ८. ४४, ७; ७२, १३.
अभिऽश्रिया १. १४४, ६; ६. ७०, १.
अभिऽश्रिषः ८. १, १२.
अभिऽश्रीः १. ९८, १; ७. ९१, ३; १०. १३०, ५.
अभिऽश्रीणन् ९. ९७, ४३.
अभिऽश्वसः १०. ९२, ८.
अभिऽश्वसन् १. १४०, ५.
अभिष्टयः १. ५२, ४; ११९, ८; ४. ३१, १०; १०. २२, १२.
अभिष्टये १. १२९, १; २. ३४, १४; ५. १७, ५; ३८, ३; ८. ८, १७; १२, ४; २७, १३; ५०, १; ६७, १; १०; ६८, ५; १०१, १; ९. ८४, २; १०. ९, ४; ४९, ४; ९३, ११[२].
अभिष्टिः १. ९, १; ३. ३४, ४; १०. १००, १२; १०४, १०.

अभिष्टिऽकृत् ४. ११, ४; २०, १; ९. ४८, ५.
अभिष्टिऽद्युम्नाः ४. ५१, ७.
अभिष्टिऽपा २. २०, २.
अभिष्टिऽभिः १. ४७, ५; १२९, ९[२]; ४. ४६, २; ५. ३८, ५; ८. ३, २; १९, २०; ५३, ५.
अभिष्टिऽमत् १. ११६, ११.
अभिष्टिऽशवसे ३. ५९, ८.
अभिष्टौ १. १५८, १; ४. १६, ४; ९; ५. ४१, ९; ६. २३, ५; ६७, ११; ७. १९, ८; ९; १०. ६, १; ६१, २२.
अभिष्णक् १०. १३१, ५.
अभिऽसत्वा १०. १०३, ५.
अभिऽसाचः ६. ६३, ९; ७. ३५, ११; १०. ६५, १४.
अभिऽसाचं ३. ५१, २.
अभिऽसाताः ५. ४१, १४.
अभिऽसृष्टः ३. ३५, १; १०. ९१, ५.
अभिऽसेनान् ६. ४४, १७.
अभिऽस्तने १. ८०, १४.
अभिऽस्तुतः ९. ३, ६; २७, १; ६७, १९; २०.
अभिस्तुते इत्यभिऽस्तुते ७. ३९, ७.
अभिऽस्थिताः १०. १६६, २.
अभिऽस्वरति १. १६४, २१.
अभिऽस्वरा २. २१, ५; ८. ९७, १२.
अभिऽस्वरे ३. ४५, २; १०. ११७, ८.
अभिऽस्वर्तारः १०. ७८, ४.
अभिऽहर्यति १०. ११२, ६.
अभिऽहितः ५. ५०, ४.
अभिऽहितौ १०. ८५, ११.
अभिऽह्रुतः १. १२८, ५[२]; १०. ६३, ११.
अभिऽह्रुता १. १८९, ६.
अभिऽह्रुतेः १. १६६, ८.
अभीके ९. ९२, ५.
अभीके १. ७१, ८; ११६, १४; ११८, ५; ११९, ८; १२१, १४; १७४, ५; १८५, १०; ३. ३९, ७; ५६, ४; ४. १२, ५; १६, १२; २४, ४; २८, ३; ४३, ४; ६. २४, १०; ५०, १०; ७. १८, २४;

८५, १; १०. ३८, ४; ५५, १;
६१, ६; १३३, १.
अभीद्धात् १०. १९०, १.
अभीपतः १. १६४, ५२.
अभीरवः १. ८७, ६; ८. ४६, ७.
अभीरुः ४. २९, २.
अभीवे ८. ४६, ६.
अभीशवः १. ३८, १२; ५. ६१, २;
८. ३३, ११.
अभीशुंऽभिः ५. ४४, ४.
अभीशूनां ६. ७५, ६.
अभीशून्ऽइव ६. ५७, ६.
अभीषाट् ७. ४, ८.
अभुक् १०. ९५, ११.
अभुंजतः १. १२०, १२; ८. १, ६.
अभुत्सि ८. ९, १६.
अभुत्स्महि ४. ५२, ४; ७. ८१, ३.
अभुवं १०. १५९, ४; १७४, ४.
अभूः ६. ३१, १; ४५, १३; १०.
२७, ७.
अभूत् १. ४६, १०; ११; १८२, १;
३. ५, ३; ४. ३४, ४; ३५, २;
५४, १; ५. ७५, ९; ६. ६४, १;
७. ७६, २; ७७, १; ७९, ३; १०.
१८, ३; ३०, १५.
अभूत् १. ११३, ११; १६१, ४; २.
३८, ६; ४. ५२, २; ६. ४७,
२०; ८. ४६, २४; ७३, १६;
१०. ८६, २३; १०२, २; १०७,
१; १४२, १.
अभूत ४. ३४, ३.
अभूत ४. ३४, ११.
अभूतन १. १९१, ५; १०. ७६, ८.
अभूतं १०. ४०, १२.
अभूतां १०. ८८, ११.
अभूतां १. १६२, २१.
अभूम ८. ४७, १८.
अभूम २. ११, १२; ४. २, १९; ६.
४४, १०; ८. २१, ७; ४८, ३;
१०. ३१, ३.
अभूवन् २. ३०, १०; ३. ३०, १५;
३१, २०; ६२, १; ५. ३, ११;
१२; १२, ५; ६. ३७, २; ७.
६१, ५; १०. २८, १२; १२४, ५.
अभूषन् ३. ५१, ८.
अभूषन् ३. ३८, ४.
अभेत् १. ३३, १३.
अभेदं १०. २८, ९.
अभेषुः ८. ४८, ११.
अभैष्म ८. ४७, १८.
अभोक्ऽहनः १. ६४, ३.
अभ्यर्धऽयज्वा ६. ५०, ५.
अभ्यसेतां २. १२, १.
अभ्रऽप्रुषः १०. ७७, १.
अभ्रं १०. २०, ४.
अभ्रंऽइव १०. ६८, ५.
अभ्रऽवर्षाः ९. ८८, ६.
अभ्रस्य ५. ८४, ३.
अभ्रा १. ७९, २; ५. ६३, ६.
अभ्राऽइव ९. ७६, ३.
अभ्राजि ५. ५४, ६.
अभ्रात् १. ६६, ३; ४. ६, ५.
अभ्राणिऽइव ६. ४४, १२.
अभ्रात् ७. ९४, १; १०. ७७, ३.
अभ्रातरः ४. ५, ५.
अभ्राताऽइव १. १२४, ७.
अभ्रातःऽइव १०. ७५, ३.
अभ्रातृव्यः ८. २१, १३.
अभ्रियः १०. ९९, ८.
अभ्रियस्यऽइव १०. ६८, १.
अभ्रियाऽइव १. ११६, १.
अभ्रियाः २. ३४, २.
अभ्रियां १. १६८, ८.
अभ्रियाय १०. ६८, १२.
अभ्रे ५. ४८, १.
अभ्रेण ५. ६३, ४; ८५, ४.
अभ्रेः ४. १७, १२; ५. ६३, ३; ९.
८७, ८.
अभ्वः १. ३९, ८.
अभ्वं १. २४, ६; ९२, ५; १४०, ५;
१६८, ९; १६९, ३; २. ४, ५;
३३, १०; ४. ५१, ९; ५. ४९, ५;
६. ४, ३; ७१, ५.
अभ्वा १. ६३, १.
अभ्वात् १. १८५, २–८.
अमंसत १०. ८६, १.
अमंहत ८. ५, ३८.
अमंहत ८. ५६, २.
अमः ५. ५६, ३; ६. ६१, ८; ८.
९३, १४.
अमंत १०. ६८, ७.
अमंतये ३. १६, ५; ७. १, १९.
अमंतिः १०. ३३, २; ३९, ६.
अमतिः १. ६४, ९; ७३, २.
अमंतिं १. ५३, ४; ३. ८, २; ५३,
१५; ४. ११, ६; ८. १८, ११;
१०. ४२, १०; ७६, ४.
अमतिं ३. ३८, ८; ५. ४५, २; ६२,
५; ६९, १; ७. ३८, २; ४५, ३.
अमतिऽवा ८. १९, २६.
अमतेः ५. ३६, ३; ८. ६६, १४;
१०. ४३, ३.
अमत्त २. ३७, ४.
अमंत्रः १. ६१, ९; ३. ३६, ४.
अमंत्रं ४. २३, ६; १०. २९, ७.
अमत्रिन् ६. २४, ९.
अमंत्रे ५. ५१, ४.
अमंत्रेभिः २. १४, १; ६. ४२, २.
अमत्सत ८. ६९, ११; ९. १४ ३.
अमत्सुः १. ८४, ५.
अमंथ्नात् १. ९३, ६.
अमंदः ८. ५४, २.
अमदुः १. ८२, ६.
अमंदत् १०. ८६, १.
अमदत् १. ८०, २.
अमंदन् १. ५२, ९; ७. १८, १२.
अमदन् १. ५२, १५; ५३, ६; १०२,
१; १०३, ७; ३. ३१, १०; ९.
८६, २४.
अमध्यमासः ५. ५९, ६.
अमनुत ४. ५, १०.
अमंत १. १२९, ३.
अमंतवः १०. १२५, ४.
अमंतिं ७. २५, २.
अमंतुः १०. २२, ८.
अमंथत् १०. १३६, ७.
अमंथत् ६. १६, १३.
अमंथतं १०. २४, ४.
अमंथिष्टां ३. २३, २.
अमंदत् १. १६५, ११; ८. ४६, २७.

अमं॑दत ५. ३४, २; ८. २१, १०.
अमं॑दथाः ८. ५२, २.
अमं॑दन् ३. ३६, ४; ५१, ९; ५. ३०, १०; ११.
अमं॑दान् १. १२६, १.
अमं॑दिपातां ७. १०३, ४.
अमं॑दिपुः ८. ५०, २; ३; १०. ४८, ४.
अ॒मं॒दि॒पुः १. ८२, ६; ८. ५२, १०.
अमं॑दीत् ८. ८०, १०.
अमं॑न्महि १. ३०, २१; ४. ३९, ४; ८. १, १४; ४५, १९; ९०, ३; १०. ३५, ८.
अ॒म॒न्म॒हि॒ ५. २२, ३; ८. १, १३; ४, १९.
अ॒म॒न्य॒त॒ ६. ७२, ३.
अ॒म॒न्यं॑त॒ १. ११६, १७.
अमं॑न्यमानान् १. ३३, ९; २. १२, १०.
अ॒म॒न्व॒त॒ १. ८४, १५.
अमं॑ १. ६६, ४.
अमं॑मदुः ७. १८, २१.
अमं॑मन् १०. ३२, ८.
अ॒म॒मं॒दुः ५. ३०, १३.
अम॑र्तः ५. ३०, ६.
अ॒म॒र्त्य॒ १. ४४, १; १२९, १०; ५. १८, २; ८. ४, १८; १०. २१, ४; १४०, ४.
अम॑र्त्यः १. ३०, १८; ५८, ३; १६४, ३०; ३८; १७५, २; ३. २, ११; ११, २; २४, २; २७, ५; ७; ४. ९, २; ५. १८, १; ७५, ९; ६. ३, ६; ९, ४; ७; १२, ३; १६, ६; ७. १५, १०; ८. १९, २४; २५; ४८, १२; ९. ३, १; ९, ६; २८, ३; ६८, ८; ६९, ५; ८४, २; १०३, ५; १०८, १२; १०. ८७, २१; १२२, ३; १४४, १.
अम॑र्त्यं १. ४४, ११; ८४, ४; १३९, ८; २. ११, २; ३७, ४; ३. १०, ९; ५१, १; ४. १, १; ८, १; ५. ४, १०; १४, १; २; ८. १९, ३; १०२, १७; १०. ११८, ६.
अम॑र्त्यस्य ८. ११, ५; १०. ७९, १; १४९, ३.
अम॑र्त्यां ३. ६१, २; ७. ७३, १; १०. १२७, २.
अ॒म॒र्त्या॒ ८. ५, २१; २६, १७.
अम॑र्त्याः १. १६८, ४; ६. १८, १५; ९. २२, ४.
अम॑र्त्ये ७. १, २३.
अ॒म॒र्त्ये॒ १. ३०, २०.
अम॑र्त्येन ६. १८, ७; १०. ६३, १७.
अम॑र्त्येपु १. ११०, ५.
अम॑र्धंतः ७. ७६, २; ५.
अम॑र्धंता ३. २५, ४.
अम॑र्धंतीः ५. ४३, १.
अ॒म॒र्म॑णः ३. ३२, ४; ५. ३२, ५; ६. २६, २.
अम॑ऽवत् १. ५२, ९; ४. ५५, ४; ५. ३४, ९; ५८, १; ८६, ३; ८. ७५, १३.
अम॑ऽवती १. १६८, ७.
अम॑वत्ऽतरेभ्यः १०. ७६, ५.
अम॑वत्ऽसु ६. ६६, ६.
अम॑ऽवंतः १. ३६, २०; ३८, ७; ८. २०, ७.
अम॑ऽवान् १. ५२, १०; ४. ४, १; ५. ८७, ५; १०. ११, ७.
अम॑विष्णवः १०. ९४, ११.
अमं॑हीयमानां ४. १८, १३.
अ॒मा १. १२४, १२; २. ३८, ६; ६. २४, १०; ५१, १५; १०. २७, २; ६३, १६; १२८, ६; १८५, २.
अ॒माऽइ॑व २. ३६, ३.
अ॒मा॒ऽजुरः ८. २१, १५; १०. ३९, ३.
अ॒मा॒जूःऽइ॑व २. १७, ७.
अमा॑त् ५. ५९, २; ८. १२, २४.
अ॒मात् ५. ५३, ८; ९. ९७, ८.
अ॒मा॑त्यं ७. १५, ३.
अ॒मा॒त्रं १. १०२, ७.
अ॒मा॒दि॒पुः ९. ८, ४.
अमा॑नुपः १०. २२, ८.
अमा॑नुपं २. ११, १०; ८. ७०, ११; १०. २२, ७.
अमा॑नुपीपु १०. ९५, ८.
अमा॑य ८. २०, ६.
अमि॑तऽओजाः १. ११, ४.
अमि॑तऽक्रतुः १. १०२, ६.
अमि॑तं ४. १६, ५.
अमि॑ता ५. ३४, १; ६. ६२, २; ७. ८४, ४; १०. ५६, ५.
अमि॑ताः १. ११९, ३; ५. ५८, २.
अमि॑तानि ८. २४, २१.
अमि॑तैः ७. ३, ७.
अ॒मि॒त्र॒ऽखादः १०. १५२, १.
अ॒मि॒त्र॒ऽदंभ॑नः ४. १५, ४.
अ॒मि॒त्र॒ऽदंभ॑नं २. २३, ३.
अ॒मित्रं॑ ६. ७३, ३; ७. ७७, ४; ८. ७५, १०.
अ॒मि॒त्र॒ऽयंतं॑ १. १३१, ७; ५. ३५, ५; १०. १८०, ३.
अ॒मि॒त्र॒ऽयुधः ३. २९, १५.
अ॒मित्रं॑स्य ६. २५, २; १०. १५२, ३.
अ॒मि॒त्र॒ऽह॒न् ६. ४५, १४; १०. २२, ८; १३४, ३.
अ॒मि॒त्र॒ऽहा ९. ११, ७; ९६, १२; १०. ८३, ३; १७०, २.
अ॒मित्रा॑ः १. १३३, १; २. १२, ८; १०. ८९, १५.
अ॒मित्रा॑न् १. ६३, २; ५; १००, ५; ३. १८, २; ४. ४, ४; १२, २; ६. ३३, १; ३; ४४, १७; ४६, ६; ८; ७३, २; ७५, ४; ७; १६; ७. १८, ९; २५, २; ३२, २५; ८५, २; ९२, ४; ८. १६, १०; ९. ९७, ५४; १०. १०३, ४; १३१, १.
अ॒मि॒त्रि॒णं॑ १. १२०, ८.
अ॒मि॒त्रि॒यं॑ ९. ६१, २०.
अ॒मि॒त्रि॒या॑ ६. १७, १; ८. ३१, ३.
अ॒मित्रे॑पु १०. ८९, ९.
अ॒मित्रैः॑ ३. ३०, १६.
अमि॑थितः ८. ४५, ३७.
अ॒मि॒नः ६. १९, १; १०. ११६, ४.
अमि॑नत् १०. ८८, १३.
अमि॑नती १. ९२, १२; १२४, २.
अमि॑नती॒ इति॑ ४. ५६, २.
अमि॑नते ४. ५, ६.
अ॒मि॒नं॒त १. ७९, २.
अमि॑नाः १. ३२, ४.
अ॒मि॒ना॒त् ३. ३४, ३; ४९, २; १०. १११, ४.
अमि॑मीत १. १२६, १; ३. २९, ११; ६. ७, ७; ८. ४२, १; १०. ९९, १०.

अमिमीत २. ४, ५: ६. ८, २: ४७, ३: १०. ६१, २: ११०, ११.

अमिमीथाः ५. ३१, ७.

अमी इति १. २४, ६; १०: १०५, ५: ९: १०: १२७, ८: १४१, १३; ४. १८, ११.

अमीतऽवर्णाः ४. ५१, ९.

अमीमदंत १. ८२, २.

अमीमेत् १. १६४, ९.

अमीमेत् १. १६४, २८.

अमीवऽचातनः १०. ९७, ६.

अमीवऽचातनं १. १२, ७: ७. ८, ६.

अमीवऽचातनीः १०. १३७, ६.

अमीवऽहा १. १८, २; ९१, १२; ७. ५५, १.

अमीवा ६. ७४, २; ९. ८५, १; १०. १६२, १; २.

अमीवाः १. १८९, ३; २. ३३, २; ३. १५, १; ७. ३८, ७; ८. ३५, १६: ४८, ११.

अमीवां १. ३५, ९; ७. १, ७; ७१, २; ८. १८, १०; ९. ९७, ४३; १०. ३७, ४; ६३, १२; ९८, १२; १००, ८.

अमीषां ६. ७५, १६; १०. १०३, १२.

अमीषि १०. ८६, ८.

अमुग्ध्वं ५. ५५, ६.

अमुघत् १०. १३८, ३.

अमुच्यत ८. ६९, १३.

अमुचः ५. २, ७; ७. १३, २; १०. १०४, ९.

अमुंचत् १०. ३०, ७.

अमुंचत् १. ६१, १०; ३. ३१, ८.

अमुंचत ४. १२, ६.

अमुंचत २. १७, २.

अमुंचतं १. ९३, ५; ११२, ८; ११७, १६; ११८, ८.

अमुंचतं १. ११६, १०; १०. ३९, १३.

अमुंचतां ८. ४०, ८.

अमुंचथाः ९. १००, ९.

अमुतः १. १७९, ४; ९. ८१, २; १०. ८५, २५[२]; १५५, २.

अमुं १. ७, ६; ८. १२, ३०.

अमुमुक्तं १. ११६, १४: ६. ५०, १०: ७. ७१, ५.

अमुया १. २९, ५: ३२, ८; ४. १८, १: ५. ३४, ५: १०. ८५, ३०: ८९, १४: १३५, २.

अमुष्णाः १. १३१, ४.

अमुष्णात् ६. ४४, २२; १०. ६७, ६.

अमुष्णीतं १. ९३, ४.

अमुष्मात् ४. २६, ६.

अमुष्मै ५. ४४, ४.

अमुष्यं १. १६४, १०; ८. ३४, १.

अमूः १. २३, १७; ६. ४७, ३१; ९. ११३, ८.

अमूं ८. ५१, ८; १०. १२५, ७.

अमूर ८. ७४, ७.

अमूर ४. ४, १२; १०. ४, ४.

अमूरः १. १४१, १२; ३. २५, ३; ४. ६, २; २६, ७; ७. ९, ३.

अमूरं ३. १९, १; ४. ११, ५; ६. १५, १७: १०. ४६, ५.

अमूरा ७. ६१, ५.

अमूराः १. ६८, ४; ७२, २; ४. ५५, २; ६. ६७, ५; ७. ४४, ५; १०. ६१, २७.

अमृक्तः ३. ११, ६; ७. ३७, १; ८. २, ३१.

अमृक्तं २. ३७, ४; ६. १, ४; ५०, ७; ७. ३७, २.

अमृक्ता ८. २४, ९.

अमृक्ताः ४. ३, १२; १०. १०४, ८.

अमृक्ते इति ३. ६, ४.

अमृक्तेन ९. ६९, ५.

अमृक्षंत १. १२६, ४; ९. २६, १.

अमृक्षाम १०. ३९, १४.

अमृणः ५. २९, १०.

अमृणत् १०. १३८, ४.

अमृणतं ४. २८, ४.

अमृत १. २६, ९.

अमृत १. ४४, ५; ११४, ६; ३. १४, ७; ४. ११, ५; ५. १८, ५; ३१, १३; ६. ५, ५; ७, ४; २१, १०; ८. ४८, ३; ९. ११०, ४.

अमृतः १. ३८, ४; ५८, १; ७०, २; ७७, १; २. १०, १; २; ३. १, १८; ३, १: ४. २, १; ५, २; ४१, १; ६. ४, २; ७. ४, ४; २०, ७; ८. ७१, ११; ९. ९१, २; १०. ४५, ८.

अमृतऽत्वं १. ९६, ६; ११०, ३; ४; १६४, २३; ३. ६०, ३; ४. ३३, ४; ३६, ४; ५४, २; ५८, १; ५. ४, १०; ६३, २; ६. ७, ४; ९. ९४, ४; १०. ५२, ५; ५३, १०; ६२, १; ६३, ४; ९२, ३; १०७, २; १२४, २.

अमृतऽत्वस्य १०. ९०, २.

अमृतऽत्वाय १. ७२, ९; ३. ३१, ९; ९. १०८, ३.

अमृतऽत्वे १. ३१, ७; ५. ५५, ४.

अमृतऽबंधवः १०. ७२, ५.

अमृतं १. २३, १९; ३५, २; ४४, ५; ६८, २; ७१, ९; ७२, ६; ८३, ५; १२५, ६; १५९, २; १८५, ६; ३. १, १४; २३, १; २६, ७; २९, ५; १३; ५३, १५; ५. २, ३; ३, ४; ५७, ५; ६. ९, ४; १५, ६; ८; ३७, ३; ४४, १६; २३; ४८, १; ७. १६, १; ७६, १; ८१, ६; ८. १३, १२; २३, १९; ५२, ७; ७४, ५; ९. ७४, ४; ६; ११३, ८; १०. १२, ३; १३, ४; ३०, १२; ९०, ३; १२१, २; १२९, २.

अमृतस्य १. १३, ५; ४३, ९; ११२, ३; १२२, ११; १६४, २१; १७०, ४; २. ४०, १; ३. १७, ४; २०, ३; ४३, ५; ६१, ३; ४. ५, १३; १६, १४; ३५, ३; ५८, १; ५. २८, २; ४७, २; ५८, १; ६. ७, ६; ७; ९, ३; १६, २५; २१, ३; ५२, ९; ७. ४, ६; ५७, ६; ८. ४२, २; १०१, १५; ९. ७०, २; ४; ९४, २; ९७, ३२; १०८, ४; ११०, ४; १०. ११, ९; १२, ६; १३, १; ८५, २०; ९३, ४; १२३, ३; १८६, ३.

अमृता १. ३५, ६; ११३, १३; ३. ५५, १०.
अमृता ५. ४२, १८.
अमृताः ५. ५७, ८.
अमृताः १. ५९, १; ६२, १०; ७२, २; १०; ९०, ३; १६६, ३; ३. ४, ११; ४. १, १०; ३, १२; ४२, १; ५. २, १२; ६९, ४; ७. ११, १; ३५, १५; ६३, ५; ८. ४८, ३; १०१, ६; १०. १६, ८; ६६, १; ५; ६९, ९.
अमृताः ७. ३८, ८; ८. ८०, १०.
अमृतात् ७. ५९, १२.
अमृतात्ऽइव १०. १७६, ४.
अमृतान् ६. १५, १८; ७. ४, ५; १७, ४; १०. ६५, १५; ६६, १३.
अमृतानां १. २४, १; २; ७. ५, १; १०. ३१, ३; ३३, ८; ७४, ३.
अमृतानि १. ७२, १; ३. ३८, ४; १०. १२३, ४; १३९, ६.
अमृता १०. १७, २.
अमृताय १. ९१, १८; ३. २५, २; ३४, २; ४. २, ९; ३, ३; ७. ९७, ५; ८. ३१, ९; ९. ६२, ६; ८७, ५; १०६, ८; १०९, ३; १०. ५३, १०; १२२, ५.
अमृतासः १. १२३, १; १२७, ८; २. १, १४; ४. ३५, ८; ५. ४२, ५; ७. ७५, ३; ९७, ५; ९. १५, २; २५, ४; १०. १०, ३.
अमृतासः १. १६६, १३.
अमृतासु १०. ९५, ९.
अमृते ९. ११३, ७.
अमृते इति १. ११३, २; ३. २५, ३.
अमृतेन ६. ७५, १८.
अमृतेभिः १. १८९, ३; १०. २०, १०.
अमृतेषु २. २, ९; ३. २१, १; २६, ३; २८, ५; ४. ४३, १; ६. १५, १०; १०. ३२, ५.
अमृत्यवः ३. २, ९; ९. ७०, ३; १०. ९४, ११.
अमृत्यु ६. ४८, १२.
अमृध्रः ५. ४३, १३; ६. १९, ७; ८. ८०, २; ९. ८२, ५.
अमृध्रं १. ३७, ११.
अमृध्राः ३. ५८, ८; ५. ३७, १; ६. ७५, ९.
अमृध्रां ६. २२, १०; ७. ६७, ५.
अमृध्रे इति ५. ४३, २.
अमे १. ६३, १; ६७, २; ४. १७, ७; ८. ५३, ८.
अमेन ४. २२, ३; ९. ९०, ६.
अमेनान् ५. ३१, २.
अमेभिः ७. ३४, १९.
अमेहयन् १०. १०२, ५.
अमैः ८. ७५, १०.
अमोचि ५. १, २; १०. १०७, १.
अंब २. ४१, १६; १०. ८६, ७[२]; ९७, २.
अंबयः १. २३, १६.
अंबरीषः १. १००, १७.
अंबरे ८. ८, १४.
अंबिऽतमे २. ४१, १६.
अंब्यं ८. ७२, ५.
अंभः १०. १२९, १.
अंभृणं १. १३३, ५.
अम्यक् १. १६९, ३.
अम्यक्षि ६. ११, ५.
अय ४. १८, २.
अयंसत १. १३५, ३[२]; ६[२]; १०. ४०, १२; ६४, २; ११९, २.
अयंस्त १. ५६, १; १३६, २; १४४, ३; ६. ७१, १; ८. २५, १९.
अयः १. १६३, ९; ४. २, १७; ५. ६२, ७; ६. ७५, १५; ८. २, ४०.
अयःऽअग्रया १०. ९९, ६.
अयःऽअपाष्टिः १०. ९९, ८.
अयःऽदंष्ट्रः १०. ८७, २.
अयःऽदंष्ट्रान् १. ८८, ५.
अयःऽशिप्राः ४. ३७, ४.
अयःऽशीर्षा ८. १०१, ३.
अयःऽस्थूणं ५. ६२, ८.
अयःऽहतं ९. १, २; ८०, २.
अयःऽहनुः ६. ७१, ४.
अयक्ष्माः ९. ४९, १.
अयच्छत् १. ६१, ११.
अयच्छत् ७. १८, १७; १०. ९८, ७; १०९, २.
अयच्छथाः १. ५२, ८.
अयजः १. ३१, ३; ७६, ५; ३. १७, २; १०. ७, ६.
अयजंत १. १२१, ५; १०. ४५, ६; १३०, ३; ६.
अयजंत १. १६४, ५०; ४. ४२, ८; ५. ३, ८; १०. ८२, ४; ९०, ७; १६; १२२, ७.
अयज्ञं १०. १३८, ६.
अयज्ञऽसाचः ६. ६७, ९.
अयज्ञान् ७. ६, ३.
अयज्ञियात् १०. १२४, ३.
अयज्यवः ७. ८३, ७.
अयज्युं १. १३१, ४.
अयज्यून् १. १२१, १३; ७. ६, ३.
अयज्योः २. २६, १.
अयज्वानः १. १०३, ६; ८. ३१, १५; १०. ४९, १.
अयज्वनां ७. ६१, ४.
अयज्वनः १. ३३, ४; ५.
अयज्वानं ८. ७०, ११.
अयत् २. ३०, ७; ५. ३७, २; ७. २०, ७.
अयतंता २. २४, ५.
अयति ८. २०, २२; ५५, १; ६६, १५[२].
अयते १. १२७, ३[२].
अयथं १०. २८, १०; ११.
अयन् ७. ६१, ४; ६३, ४; १०. १२, ४.
अयन् ४. २, १६.
अयनं ३. ३३, ७.
अयंत ६. २६, १.
अयंते १. ११९, २.
अयंत्रः १०. ४६, ६.
अयं १. १६, ७; २०, १; २४, १२; ३०, ४; ४५, १०; ४७, १; ५०, १३; ९४, १२; १०४, ९; १०८, २; ६; ११०, १; १२०, ११; १२१, १३; १२८, १; १३०, १; १३५, २; ३; १३६, ४; १३७, ३; १४९, ५; १६०, ४; १६१, १४; १६४, २९; ३५[२]; १७७, ४[२];

१८१, १; १८३, ४; २. ५, ८; १८, ४; ६; ३८, २; ४१, २; ४; २४; ३. ८, ११; १६, १; २२, १; २९, ९; १०; ३५, ६; ४४, १; ५३, २०; ५९, ४; ६२, २; ४. ३, २; ७, १; १३, ५; १५, ४; १७, ९^{२}; १०^{२}; १४; १८, १; ३४, ३; ४६, ६; ४९, २; ५. ३, १२; ३०, ३; ३१, १२; ४०, २; ४४, १४; ५१, ४; ५८, ३; ६. ३, ३; ९, ४^{२}; १२, १; ३९, २; ३; ४^{३}; ४१, ४; ४३, १; ४४, २२^{२}; २३^{२}; २४^{३}; ४७, १^{४}; २; ३^{३}; ४^{३}; ५^{२}; ४८, २; ६८, ९; ७. १, १६; ४, ४; ८, २; ४; २४, ५; २९, १; ३२, १७; ३६, ९; ४०, ४; ५५, ५; ६८, ४; ७४, १; ८६, ३; ८; ९५, ६; ८. २, २८; ३, ४; ५, १८; ९, ४^{२}; ६; १८; १३, ३०; ३१; १७, ७; ११; १२; २२, ८; २५, १६; ३२, २०; ३३, ७; १३; ४४, १६; २८; ४८, १०; ५१, ९; ५७, ४; ६४, १०; ११; ६७, ८; ७५, ४; ७६, २; ४; ७९, १; ८२, ५; ८५, ३; ८८, ४; ९४, ४; १००, १; ४; १०१, ९; १०२, ८; ९; ९. ३९, ४; ४४, ३; ५४, २^{२}; ३; ६२, १०; ६७, ११; १२; ६८, ९; ७७, ४; ८६, १३; २१^{२}; १०१, ७; १०२, ४; १०५, ३^{२}; १०६, २; १०. ६, १; १६, ९; १७, १३; २५, १०^{२}; ११^{२}; २६, २; २७, १८; २१; ३२, ९; ३४, १३; ३९, ५; ५१, ९; ५२, ३; ५३, १; ६०, ७^{३}; १२^{४}; ६१, १६; १९; ६२, ४; ८; ६९, ७; १२; ७७, ४; ८३, ६; ८६, ३; ९; १८; १९; ९९, ९; १०^{२}; १०८, ७; १२३, १; १२४, ६; १२६, ३; १३५, ७; १३७, ५; १४२, १; १४४, १; २^{२}; ६; १५९, १; १७३, ४; १७६, ३; ४; १८९, १.

अर्यमानः ८. १००, ८.

अर्यमानं ४. ३८, ५.

अयष्ट ६. ४७, २५.

अयंसः ६. ३, ५; ४७, १०.

अयंसे १. ५७, ३; ४. २१, ७.

अयस्मयः ५. ३०, १५.

अयां ६. ६६, ४.

अया १. १२८, २; १४३, ६; १६६, १३; २. ६, २; २४, १; ३. १२, २; ४. ४, १५; ५. ४५, ११^{२}; ६. १७, १५; २२, ६; ७१, ६; ८. १, १८; १३, ८; २३, ७; ९३, १७; ९. ४७, १; ५३, २; ६१, १; ६३, ७; ६५, १२; ९७, ५२; १०६, १४; १११, १.

अयांसं २. ३५, १५^{२}.

अयाः ६. ६६, ५.

अयाः ३. २९, १६.

अयांःऽइव १०. ११६, ९.

अयात् १०. ८५, ७.

अयातन ५. ५४, ५; ८. ७, २६.

अयातन १. १६१, ७.

अयातं १. ११६, १८; ५. २९, ९; १०. ८५, १४; १५.

अयातं १. ११६, १९; २०; ५. ३१, ८.

अयातयंत १. ३३, ६.

अयातुः ७. ३४, ८.

अयातुं ७. १०४, १६.

अयान् २. ३८, ३; ४. ५३, १; ६. ७१, ५; १०. १३९, १.

अयाम १. ३३, १; ५. ४५, ५; ८. ९२, ११.

अयामन् १. १८१, ७; ८. ५२, ५.

अयामि १. १५३, २; ३. १४, २; ६. ११, ५; ७. २३, २.

अयामि २. ४१, २; ४. ४७, १; ६. ३४, ४; ७. ६४, ५; ९२, १; ८. १०१, ९.

अयासः ७. ५८, २.

अयासः १. ६४, ११; १५४, ६; १६७, ४; ३. १८, २; ५४, १३; ४. ६, १०; ५. ४२, १५; ६. ६६, ५; ९. ४१, १.

अयासं ९. ८९, ३; ४.

अयासं ३. ३३, ३.

अयासां १. १६८, ९; १६९, ७.

अयासिषं १. १८, ६.

अयासिषुः ९. ६१, १३.

अयासिष्ट ५. ५८, ६.

अयासीत् ९. ८६, १६; ९०, १; ९२, ६.

अयासुः ७. ५७, १.

अयासुः ९. ९७, ८.

अयास्यः १. ६२, ७; ८. ६२, २; ९. ४४, १; १०. ६७, १; १०८, ८; १३८, ४.

अयुक्त १. ५०, ९; ११५, ४; ५. १७, ३; ४५, १०; ८७, ४; ६. ६३, ४; ७. ६०, ३; ९. ६३, ८.

अयुक्त १. ४८, ७; ९. ६३, ९.

अयुक्त १०. २७, ९.

अयुक्ताः ९. ९७, २०.

अयुक्तासः ५. ३३, ३.

अयुक्थाः १. ९४, १०.

अयुक्षत १. ९२, २; ३. २६, ४; ८. ४१, ६.

अयुक्षातां १. १५७, १; १०. ३५, ६.

अयुग्ध्वं १. ६४, ७; ८५, ४; ५; ५. ५५, ६; ५७, ३.

अयुग्ध्वं १. ३९, ६.

अयुजः ८. ६२, २.

अयुजि ५. ४६, १.

अयुज्महि ६. ५३, १.

अयुंजन् १. १६९, २; ३. ४१, २.

अयुंजत १. १३०, ५.

अयुतं ४. २६, ७.

अयुता ८. २, ४१; २१, १८; ४६, २२.

अयुतानि ८. ३४, १५.

अयुताय ८. १, ५.

अयुद्धः ८. ४५, ३; १०. २७, १०.

अयुद्धऽसेनः १०. १३८, ५.

अयुध्यः ४. ३०, ५.

अयुध्यः १०. १०३, ७.

अयुध्यत १०. ८, ८.

अयुध्वी १०. १०८, ५.

अयुनक् १. १६३, २; ६. ४४, २४; १०. १०२, ७.

अयुयुत्सन् १. ३३, ६.

अयोः १. १८५, १; ६. २५, ६.

अयोंजि ५. ७५, ९.
अयोजि १. १२३, १; ९. ८८, २.
अयोद्धाऽइव १. ३२, ६.
अयोधयः १. ३३, ७.
अयोधीत् ४. ३८, ८.
अयोयवीत् १. ५२, १०.
अरंस्त २. ११, ७.
अरंहः ५. ३२, २.
अरंहत १०. १०२, ७.
अरंहयंत १०. ११३, ६.
अरक्षः ५. ८७, ९.
अरंक्षत् १. ७४, २.
अरक्षत ६. ८, २.
अरंक्षन् १. १४७, ३; ४. ३३, ४.
अरक्षन् १. १४८, ५; ४. २७, १; १०. ३३, १.
अरक्षसः १. १९०, ३.
अरक्षसं ७. ८५, १; ८. १०१, ८.
अरक्षसा १. १२९, ९; २. १०, ५.
अरज्जुऽभिः ७. ८४, २.
अरज्जौ २. १३, ९.
अरद्वे ८. ४६, २७.
अरंणः २. २४, ७; ५. २, ५; ६. ७५, १९; ७. ४, ८.
अरंणं ३. ५३, २४; ५. ८५, ७; ८. ४, १७; १०. ११७, ४.
अरंणयन् १०. ८८, २.
अरंणस्य ७. ४, ७.
अरंणाःऽइव ८. १, १३.
अरंणानि ६. ६१, १४.
अरणिंऽभिः १. १२७, ४; १२९, ५.
अरणी इति ५. ९, ३; १०. १८४, ३.
अरंणीं १०. १२४, २.
अरंणे १०. ६३, १६.
अरंण्यानि १०. १४६, १[२].
अरण्यानिः १०. १४६, २; ३; ५.
अरण्यानिं १०. १४६, ६.
अरण्यान्यां १०. १४६, ४.
अरंण्ये ६. २४, १०.
अरंण्येषु १. १६३, ११.
अरण्योः ३. २९, २; ७. १, १.
अरतं ८. ५, १३.
अरतये ७. ५, १.

6

अरतां ३. ३३, १३.
अरतिः १. ५९, २; १२८, ६; २. २, २; ४, २; ४. २, १; ६. ३, ५; १२, ३; ६७, ८; १०. ३, १; २; ६; ७; ४५, ७; ६१, २०.
अरतिं १. ५८, ७; १२८, ८; २. २, ३; ३. १७, ४; ४. १, १; ३८, ४; ६. ७, १; १५, ४; ४९, २; ७. १०, ३; १६, १; ८. १९, १; २१; १०. ४६, ४.
अरतौ ५. २, १.
अरत्नयः ८. ८०, ८.
अरत्नौ १०. १६०, ४.
अरथाः ५. ३१, ५; ९. ९७, २०; १०. ९९, ४.
अरंथीः ६. ६६, ७.
अरंदः ६. ३०, ३; ७. ७९, ४.
अरदुः ४. १९, २.
अरंदत् ७. ४७, ४; १०. ८९, ७.
अरदत् ३. ३३, ६; १०. ७५, २.
अरदतं १. ११६, ७.
अरंध्रं ६. ६२, ३.
अरंध्रस्य ६. १८, ४.
अरन् १. १२५, ७; ५. ३१, १३.
अरंत ५. ३१, ८.
अरंत ४. १९, ९; ९. ७३, १; १०. ७३, २.
अरंधनायः १. ५३, १०.
अरंधयः १. ५१, ६; २. ११, १९; ५. २९, ११; ६. २३, २; ७. १९, २.
अरंधयत् ७. १८, ९.
अरंधयत १. १३०, ८.
अरंधयं १०. ४९, ५.
अरपः १०. १५, ४; ३७, ११.
अरपत् १. ११९, ९; ५. ६१, ९.
अरपाः २. ३३, ६; ८. १८, ९; १०. १३७, ५.
अरंध्र १०. ८, ३.
अरं १. ६६, ३; ७०, ३; १०८, २; १४२, १०; १७०, ४; १७३, ६; १८७, ७; २. ५, ७; ८; १७, ६; १८, २; ३. ३५, ५; ४. ३२, २४[२]; ३३, २; ५. ४४, ८; ६६, ५; ६. १३, ४; १६, ४३; ४१, ५; ६३, २; ७४, १; ७. ७, ६; ६६, १४; ६८, २; ८६, ७; ८. १५, १३; ४५, १०; ४६, १७; ८२, ३; ९२, २४[२]; २५[२]; २६[२]; २७; ९. २४, ५; १०. ९, ३; ६३, ६; ७१, १०; ९६, ७; ९७, १८; १०१, २; १०६, ८; ११७, ३.
अरं ४. १५, ७; ६. ३५, ५.
अरमतिः २. ३८, ४; ७. १, ६; ३४, २१; ८. ३१, १२; १०. ६४, १५; ९२, ४.
अरमतिं ५. ४३, ६; ५४, ६; ७. ३६, ८; ४२, ३; १०. ९२, ५.
अरऽमनसं ६. १७, १०.
अरमंत ३. ५६, ४.
अरंममाणः ९. ७२, ३.
अरंमयः २. १३, १२; ४. १९, ६; ५. ३१, ८.
अरंऽकृतः १०. १४, १३; ११९, १३.
अरंऽकृतः १. १४, ५; ८. ५, १७.
अरंऽकृतं ८. १, १०.
अरंऽकृताः १. २, १.
अरंऽकृतिः ७. २९, ३.
अरंऽकृते २. १, ७; ८. ६७, ३.
अरंऽकृत्यं १०. ५१, ५.
अरंऽगमाय ६. ४२, १; ८. ४६, १७.
अरम्णाः ५. ३२, १.
अरंम्णात् २. १२, २.
अरम्णात् २. १५, ५; १०. १४९, १.
अरये ६. १३, ५.
अररुः ८. ४, २१.
अररिंदानि १. १३९, १०.
अररिऽवान् १. १४७, ४.
अररुं १. १२९, ३; १०. ९९, १०.
अररुषः १. १८, ३; १५०, २; ३. १८, २; ५. ७७, १; ७. १, १३; ९. २९, ५.
अररुषे ७. ५६, १९.
अरश्मानः ९. ९७, २०.
अरसं १. १९१, १६[२].
अराः १०. ७८, ४.
अराःऽइव ५. ५८, ५.

अराजिनः ८. ७, २३.
अराजिषुः ८. १४, १०.
अराणां ८. २०, १४.
अराणिषुः ८. १३, १६.
अरातयः १. २९, ४; ४३, ८; २. २३, ५; ९; ३५, ६; ५. २, ६; ६. ४८, १६; ५९, ८; ७. ८३, ३; ५; ८. ९, १; ७१, ४; ९. ७९, १; १०. ५७, १; ८५, ३२; १३३, ३; १७४, २.
अरातिः २. ७, २; ८. ४८, ३; १०. ३४, १४.
अरातिं ४. ४, ४; १०. ६३, १२.
अरातिऽयतः १. ९९, १.
अरातिऽवा १. १४७, ४; २. २३, ७; ८. ६२, ११; ९. ११४, ४.
अरातीः १. ११६, २१; ३. १८, १; २४, १; ४. २६, ७; २७, २; ५०, ११; ५. ५३, १४; ६. ४, ५; १६, २७[२]; ४४, ९; ७. १, ७; ८. ११, ३; ३९, २[२]; ९. ९६, १५; ९७, १०.
अरातेः ८. ७१, १.
अरात्याः ९. ७९, ३[२].
अराधसः ५. ६१, ६; ८. ६४, २; १०. ३२, २; ६०, ६.
अराधसं १. ८४, ८; ९. १०१, १३.
अराधि १. ७०, ४; १०. ५३, २.
अराध्वं १. १६६, १२; ७. ५९, ४; ८. ४७, ७.
अरान् १. ३२, १५; १४१, ९.
अरान्ऽइव ५. १३, ६; ८. ७७, ३.
अराम ७. ५६, २१; ८. २१, १६.
अरायासः ८. ६१, ११.
अरायि १०. १५५, १.
अराय्यं १०. १५५, २.
अरावा ७. ५६, १५; ६८, ७; ८. २८, ४; ९. २१, ५; १०. ३७, १२.
अराविषुः १०. ९४, ६.
अराविषुः १०. ९४, ३.
अरावीत् ९. ७४, ५.
अरावीत् ९. ७१, ९; १०. ८, २.
अराव्णः १. ३६, १५; १६; ८. ६०, १०, ९. १३, ९; ६१, २५; ६३, ५.
अराव्णे ७. ३१, ५.
अरासत १. १६६, ३; ५. ७९, ६; ८. ४७, ४.
अरासत ३. ५३, १३.
अरिः १. ४, ६; ९, १०; १५०, १; ७. ६४, ३; ८. २, १४; ५१, ९; ७२, १६; ९. ७९, ३; १०. २८, १; ३९, ५.
अरिऽगूर्तः १. १८६, ३.
अरिच्यत २. २२, २; १०. ९०, ५.
अरिणक् २. १३, ५.
अरिणाः २. २२, ४; ४. ३०, ६.
अरिणाः १. ५६, ६; ४. १९, ५; ४२, ७.
अरिणात् २. १२, ३; ३. ३, ११; ४. २८, १.
अरिणात् २. १५, ६.
अरिणीत ३. ६०, २.
अरिणीत १. १६१, ७; ४. ३६, ४.
अरिणीतं १. ११७, ११.
अरिताऽइव २. ४२, १.
अरित्रऽपरणीं १०. १०१, २.
अरित्रं १. ४६, ८.
अरित्राः १०. ४६, ७.
अरिऽधायसः १. १२६, ५.
अरिप्रं ७. ४७, १; १०. ७१, १.
अरिप्रा ८. ८, ९.
अरिप्राः ७. ९०, ४; १०. १२०, ९.
अरिं २. ८, २; ५. ४८, ५.
अरिरेचीत् ४. २४, ९; ६. २०, ४; १०. १३, ४.
अरिषण्यन् १. ६३, ५; २. ३७, ३; ६. २४, ९; २५, २.
अरिषण्या २. ३९, ४.
अरिष्टः १. ४१, २; ५. १८, ३; ३१, १; १०. ६३, १३; १६६, २.
अरिष्टऽगातुः ५. ४४, ३.
अरिष्टऽग्रामाः १. १६६, ६.
अरिष्टऽतातये १०. ६०, ८; ९७, ७.
अरिष्टतातिऽभिः १०. १३७, ४.
अरिष्टऽनेमिः १. ८९, ६.
अरिष्टऽनेमिं १. १८०, १०; १०. १७८, १.
अरिष्टऽनेमे ३. ५३, १७.
अरिष्टऽभर्मन् ८. १८, ४.
अरिष्टं २. ३४, ७.
अरिष्टऽरथः १०. ६, ३.
अरिष्टऽवीराः १. ११४, ३.
अरिष्टाः २. २७, २; ७; १६; ५. ४२, ८; ६. १९, ४; ७. ४३, ५; १०. १२८, ३.
अरिष्टान् ७. ४०, ४; ९७, ४.
अरिष्टाभिः ६. ५४, ७.
अरिष्टां १०. ८५, २४.
अरिष्टिं २. २१, ६.
अरिष्टेभिः १. ११२, २५; ८. २७, ४.
अरिष्टैः ६. ६९, १.
अरिष्यंतः २. ८, ६; ४. ५७, ३; ८. २५, ११; १२.
अरिष्यंतं १०. ६३, १४.
अरिऽस्तुतः ८. १, २२.
अरीत ९. ७९, ३.
अरीरमत् २. ३८, ३; ६. ७१, ५.
अरीळ्हं ४. १८, १०.
अरुक्षत् १०. ६७, १०.
अरुग्णं ६. ३९, २.
अरुचः ६. ३९, ४.
अरुजः ३. ३२, १६; ४. ३२, १०.
अरुजः १. ५१, ५; ५६, ६; ६. ३०, ५.
अरुजत् ६. ६१, २.
अरुजं १०. ४९, ६.
अरुणऽअश्वाः ५. ५७, ४.
अरुणः १. १०५, १८; १३०, ९; ९. ४०, २; १०. ३०, २; ५५, ६.
अरुणऽप्सवः १. ४९, १; ८. ७, ७.
अरुणऽप्सुः ८. ५, १; ७३, १६.
अरुणऽप्सुं ५. ८०, १.
अरुणं १. ७३, ७; ७. ९८, १; ८. १०१, ६; ९. ४५, ३; ७८, ४; १०. १४४, ५.
अरुणयः १०. ९५, ६.
अरुणयुक्ऽभिः ६. ६५, २.
अरुणस्य १०. ९४, ३.
अरुणा १. १३४, ३.
अरुणाः १. ९२, २.
अरुणान् १. ९२, १५.
अरुणानां १. १२४, ११.
अरुणानि १०. १६८, १.

अरुणां ५. ६३, ६.
अरुणाय ९. ११, ४.
अरुणासः ६. ६४, ३.
अरुणीः १. ११२, १९; १२१, ३; ४. १, १६; २, १६; १४, ३.
अरुणीनां १०. १५, ७.
अरुणीषु १०. ६१, ४.
अरुणेभिः १. ८८, २; ११३, १४; २. ३४, १३; ५. ८०, ३.
अरुणैः २. १, ६; ३४, १२.
अरुण्यः १. १४०, १३.
अरुंतऽहनुः १०. १०५, ७.
अरुंपितं ४. ५, ७.
अरुशऽहा १०. ११६, ४.
अरुषः ३. १५, ३; २९, ६; ४. ५८, ७; ५. १, ५; ४७, ३; ५६, ७; ६. ३, ६²; ४८, ६²; ७. ३, ३; ९. ८, ६; २५, ५; ६१, २१; ७१, ७; ७२, १; ७४, १; ८२, १; १११, १; १०. १, ६; २०, ९; ४३, ९.
अरुषं १. ६, १; ३६, ९; ११४, ५; ३. १, ४; ४. १५, ६; ५. ४३, १२; ६. ४९, २; ७. ९७, ६; ८. ६९, १६; ९. ८९, ३; १०. ४५, ७; ८९, ९.
अरुषऽस्तूपः ३. २९, ३.
अरुषस्य १. ८५, ५; ३. ७, ५; ३१, ३; ५. १२, २; ६; ६. ८, १; ४९, ३; १०. ९२, २.
अरुषा १. ९४, १०; २. १०, २; ४. २, ३; ६. २७, ७; ७. १६, २.
अरुषाः १. ११८, ५; ५. ७३, ५; ७. ४२, २.
अरुषाय ७. ७१, १.
अरुषासः १. १४६, २; ४. ६, ९; ४३, ६; ५. ५९, ५; ७. १६, ३; ७५, ६; ९७, ६; ८. ३४, १७.
अरुषि १. ३०, २१.
अरुंषी ३. ५५, ११; ४. ५२, २; ८. ६८, १८.
अरुंषीः १. १४, १२; ७२, १०; ९२, १; २²; ८. ६९, ५; १०. ५, ५; ८, ३.
अरुंषीणां ८. ५५, ३.
अरुंषीभिः ९. १११, २.
अरुंषीं १. ७१, १.
अरुषेण २. २, ८.
अरुषेभिः १. १४१, ८.
अरुषैः ३. ३१, २१.
अरुहः ९. ८३, ५.
अरुंहत् १. १०, २; १४१, ५.
अरुहत् १. ५१, २; ११९, २; ३. २, १२; ५. १०, २; ४५, १०; ६. ७१, ५; ७. ६०, ४; ८३, ३; ८. ४१, ८; ४८, ११; ७२, ४; ९. ७५, १; ८६, ४०; ८९, २.
अरुंहन् ८. १००, ५; १०. ४०, ९.
अरुहन् १. ११०, ६.
अरूंक्षितं ४. ११, १.
अरूंरुचत् ९. ८३, ३; ८५, ९.
अरूरुचत् ९. ८५, १२.
अरेंजंत १. ३८, १०.
अरेंजेतां १. ३१, ३; १५१, १; २. ११, ९.
अरेणवः १. ३५, ११; १५१, ५; १६८, ४; ६. ६६, २; १०. १४३, २.
अरेणु १. ५६, ३.
अरेणुऽभिः १. १६३, ६; ६. ६२, ६.
अरेपसः १. ६४, २; ५. ५३, ३; ५७, ४; ६१, १४; ९. १०१, १०; १०. ७८, १; ९१, ४.
अरेपसं ५. ६३, ६; ७३, ६; ९. ७०, ८.
अरेपसा १. १२४, ६; १८१, ४; ५. ७३, ४.
अरेपसौ ५. ५१, ६.
अरेपाः ४. १०, ६; ६. ३, ३; १०. १०५, १०.
अरैक् १. ११३, २; १६.
अरैक् १. ११३, १; १२४, ८; ३. ३१, २.
अरोचत १०. ८८, ७.
अरोचत ३. २९, १४; ५. १४, ४; ८. ५६, ५².
अरोचथाः ३. २९, १०.
अरोचयः ९. ६३, ७.
अरोचयः ३. ४४, २; ८. ९८, २.
अरोचयत् १. १४३, २; ३. २४, ४; ८. ३, ६; ९. ९, ३; २८, ५; ३७, ४.
अरोचयन् ८. २९, १०.
अरोचि ७. १०, २; ७७, २.
अरोदयत् १०. ६७, ६.
अरोदयत् १०. ९९, ५.
अरोधं १०. ३४, २.
अरोरवीत् २. ११, १०; ५. ३०, ११.
अरोरवीत् ८. ६, ४०.
अरोहत् ३. ७, ३; १०. ८५, १२.
अरोहं १०. १३, ३.
अरोहयः १. ५१, ४; ९. ८६, २२.
अरोहयन् १०. ६२, ३.
अर्कः १. ८३, ६; १६७, ६; ३. २६, ७; ६. २१, ४; ७. २४, ५; ८. ८८, ४; ८९, ६; १०. ६८, ४.
अर्कं १. १०, १; १९, ४; ६१, ५; ६२, १; ८५, २; १६४, २४; १६६, ७; १८६, ४; ३. २६, ८; ५. ३०, ६; ३१, ५; ६. ४९, ८; ६६, ९; ७. ९, २; ३९, ७; ९७, ५; ८. ५१, ४; १०; ९२, १९; १०१, १४; ९. ७३, २; १०. ६७, ५; ७८, ४; १०७, ४; ११२, ९; ११४, १; १५३, ४; १५७, ५.
अर्कऽशोकैः ६. ४, ७.
अर्कऽसातौ १. १७४, ७; ६. २०, ४; २६, ३.
अर्कस्य १. १३१, ६; ८. ६३, ४; ९. २५, ६.
अर्काः ३. ५४, १४; ५. ५, ४; ५७, ५; ८. ६३, ५; ६; ९. ९७, ३५; १०. ६८, १.
अर्किणः १. ७, १; १०, १.
अर्किणं १. ३८, १५.
अर्किणी ८. १०१, १३.
अर्केण १. १६४, २४; ६. ६५, ५; १०. ६८, ९.
अर्केभिः १. ७, १; ६. ५, ५; ८. १६, ९.
अर्केषु १. १७६, ५.
अर्कैः १. ३३, २; ४७, १०; ६२, ७; ११; ८८, ४; १४१, १३; १९०, १; २. ११, १५; ३. ३१, ९; ११; ३४, १; ६१, ६; ६२, ५; ४. ३,

१५; १०, ३; १६, ४; ४४, ३; ५५, ३; ५६, १; २; **५.** २९, १२; ३१, ४; ३३, २; ४१, ६; ७; **६.** ३, ८; ४, ६; २०, १३; २१, १०; ३८, ३; ४९, १४; ५०, १५; ६२, १; ६९, २; ७३, ३; **७.** २३, ६; **८.** १२, २३; **९.** ९७, ३१; **१०.** ६, ४; १५, ९; ६८, ६; ११६, ९; १४८, ५.

अर्च॑ **१.** ५४, २; ३; **५.** १६, १; २२, १; ५२, १; ५९, १; **६.** १६, २२; ६८, ९; **८.** ४१, १; ५०, १; **१०.** ५०, १.

अ॒र्च॒ **३.** १३, १; ५४, २; **५.** २५, ७; ५२, ५; ८५, १; **६.** ५०, ६; **८.** २३, २४; ४०, ४; ४९, १; ६९, ४; **१०.** ७६, ५; ८९, ३; ११२, ९; १४८, ३.

अर्च॑त् **१.** १७३, २.

अ॒र्च॒त् **१.** १६५, १४.

अर्च॑त **६.** ४५, ४; **८.** ६९, ८[?].

अ॒र्च॒त॒ **१.** ५१, १; ८०, ९; ८४, ५; १०१, १; १५५, १; **२.** १७, १; **३.** ५१, ४; **५.** ५४, १; **७.** ५८, १; **८.** १, ८; ६९, ८[?]; ८९, ३; ९२, ५; ९३, २६; **९.** ११, ४; **१०.** ६४, ९; ९२, १३; ९४, ७; ९६, २; १३३, १.

अर्च॑तः **७.** २२, ४; २८, ५; **१०.** ८९, १६.

अर्च॑ति **७.** २२, ३.

अ॒र्च॒ति॒ **१.** ६, ८; ९, १०; १०१, ७.

अ॒र्च॒तु॒ **१०.** ३६, ५.

अर्च॑ते **१.** ८७, २; १५१, २; **५.** ६४, २.

अ॒र्च॒त्ऽधू॑मासः **१०.** ४६, ७.

अ॒र्च॒त्र॑यः **६.** ६६, १०.

अ॒र्च॒त्र्यः **६.** २४, १.

अर्च॑थः **१.** १५१, ६.

अर्च॑न् **१.** ८०, १–१६; **३.** ३१, ७; ८; **१०.** १४९, ५.

अ॒र्च॒न् **३.** १४, ४; **४.** १, १४; **७.** ४३, १.

अ॒र्च॒नान॑सं **५.** ६४, ७.

अर्च॑तः **१.** ६२, २; ८५, २; **३.** ३२, ३; **५.** १३, १[?]; **८.** २९, १०.

अर्च॑ति **१.** १०, १; ९२, ३; १६५, १; १६६, ७; **५.** २९, १; ६; ३०, ६; **१०.** १४७, ३.

अ॒र्च॒ति॒ **१.** १३२, ५; **३.** १२, ५; **५.** २९, १२; **६.** २१, १०; ५०, १५; **७.** २३, ६; **१०.** १, ३.

अर्च॑तु **८.** ६९, ८.

अ॒र्च॒तु **८.** ९२, १९.

अ॒र्च॒थ॑ः **१.** ३६, ३; २०; ४४, १२; ४८, १३; **४.** ६, १०; **५.** ६, ७; ९, ५; १७, ३; २५, ८; **८.** ४४, ४; १७; **९.** ६६, ५; **१०.** १४०, १.

अ॒र्च॒य॒ः **३.** ४४, २.

अ॒र्च॒से॒ **१०.** ६४, ३.

अ॒र्चाऽइ॑व **६.** ३४, ४.

अर्चा॑त् **४.** १६, ३.

अर्चा॑न् **४.** ५५, २; **५.** ३१, ५.

अर्चा॑म **१.** ६२, १; १७३, १.

अ॒र्चा॒म॒ **९.** ९७, ४; **१०.** १६५, १.

अर्चा॑मसि **६.** २१, ६.

अर्चा॑मि **१.** १३८, १; **४.** ४, ८; **१०.** १२, ४.

अ॒र्चिः **१.** ९२, ५; **३.** ६, ३; **४.** ७, ९; **८.** ४३, १०; **१०.** १६, ४; १४२, ६.

अ॒र्चिनः **२.** ३४, १; **५.** ४५, १.

अ॒र्चिना **८.** ४१, ८.

अ॒र्चिऽभिः **५.** ७९, ८; **६.** ४८, ७.

अ॒र्चि॒ऽमंता **१०.** ६१, १५.

अ॒र्चि॒ऽवत् **७.** ८१, २; **९.** ६७, २४.

अ॒र्चिषा **१.** १५७, १; **२.** ८, ४; **५.** १७, ३; ७९, ९; **६.** ४८ ३; ६०, १०; **८.** ७, ३६; ४३, ८; **१०.** ८७, २; ११; १४; १७; ८८, ९; १२.

अ॒र्चिषि **९.** ६७, २३.

अ॒र्ची॑षि **७.** ६२, १.

अ॒र्चे॒ **५.** ४१, ८; **६.** २२, १.

अ॒र्जु॒न॒ **७.** ५५, २.

अर्जु॑नं **३.** ४४, ५; **६.** ९, १; **९.** ६९, ४.

अर्जु॑नस्य **१.** १२२, ५.

अर्जु॑ना **३.** ३९, २; **१०.** २१, ३.

अ॒र्जु॒नि॒ **१.** ४९, ३; **५.** ८४, २.

अर्जु॑ने **९.** १०७, १३.

अर्जु॑न्योः **१०.** ८५, १३.

अर्णः **१.** ३, १२; १२२, १४; १६७, ९; **२.** १९, ३; **३.** ३२, ११; **४.** १९, ६; **५.** ४५, १०; **६.** ४७, ५; **७.** ६०, ४; **८.** २०, १३; **९.** ८६, ३४; ९७, २१; **१०.** ८, ३.

अर्णः॑ऽभिः **४.** ३, १२.

अ॒र्णः॒ऽवृ॑तं **२.** १९, २.

अर्णं **३.** २२, ३; **५.** ३२, ८.

अ॒र्ण॒वः **१.** ५५, २; **३.** २२, २; **६.** ६१, ८; **७.** ६३, २; **९.** ८६, ४५; **१०.** ६६, ११; १९०, १.

अ॒र्ण॒वं **१.** १९, ७; ५१, १; ५६, ५; ८५, ९; १६८, ६; **२.** २३, १८; **३.** ५१, २; ५३, ९; **८.** ४०, ५; **१०.** १०, १; ५८, ५; ६५, ३; ११५, ३.

अ॒र्ण॒वस्य॑ **१०.** ६७, १२.

अ॒र्ण॒वात् **१०.** १९०, २.

अ॒र्ण॒वान् **५.** ३२, १.

अ॒र्ण॒वे **८.** २६, १७.

अ॒र्ण॒वैः **५.** ५९, १.

अर्ण॑सः **१.** ११७, १४; १५८, ३; १८२, ७; **६.** ६२, ६; **७.** ६९, ७.

अ॒र्ण॒सं **५.** ५४, ६.

अर्ण॑सा **९.** २१, ६; १०७, १२.

अर्ण॑ऽसातौ **१.** ६३, ६; **२.** २०, ८; **४.** २४, ४.

अर्णा॑ **३.** ३२, ५; **५.** ५०, ४.

अर्णा॑सि **१.** ५२, २; ६१, १२; १७४, ४; १८०, १; **४.** १६, ७; **६.** ७२, ३; **७.** १८, ५; ८७, १; **१०.** ४९, ९.

अर्णाः॑ **१.** १७४, २; **५.** ४१, १४.

अर्णा॑चि॒त्रर॑था **४.** ३०, १८.

अ॒र्ते॒ **४.** १, १७; १६, ९; **५.** २५, ८; ५२, ६.

अर्थि॑ **१.** १०, २; ३८, २; १०५, २; १२४, १; १३०, ५; १४४, ३; १५८, ६; **२.** ३०, २; ३९, १; **३.** ११, ३; ५३, ५; ६१, ३; **४.** ६,

१०; १३, ३; ६. ३२, ५; ७. १८, ९; ८. ६९, १७; ७९, ५; ९. १, ५; १०. १८, ४; २७, २०; २९, ५; ५१, ४; ६; ५९, १; ७३, ५; १४३, १.

अर्थेऽइव १. ११३, ६.

अर्थयंति ५. ४४, ११.

अर्थयस्व २. १३, १२; १४, १२.

अर्थयासे १. ८२, १.

अर्थयेथे इति १०. १०६, १.

अर्थानि ७. ६३, ४.

अर्थिनः १. ४८, ६; १०५, २; ८. २७, १२; ७९, ५; १०. २६, ८; १२७, ५.

अर्थी ७. १, २३.

अर्थेषु १०. १०६, ७.

अर्दय २. २३, १४; ८. ७५, १०.

अर्दयः ८. ५३, २.

अर्दयः १०. १४७, २.

अर्दयत् १. १८७, १.

अर्धः १०. २७, १८.

अर्धऽगर्भाः १. १६४, ३६.

अर्धऽदेवं ४. ४२, ८; ९.

अर्धे १. १६४, १७; ६. ४७, २१; १०. २८, ५.

अर्धे २. ३०, ५; ४. ३२, १; ६. ३०, १; ४४, १८; ७. १८, १६.

अर्धे १. ९२, १; १२४, ५; १६४, १२; ६. २७, ५.

अर्धौ २. २७, १५.

अर्ध्यः १. १५६, १.

अर्ध्ये ५. ४४, १०.

अर्पय २. ३३, ४.

अर्पयतं ७. १०४, १.

अर्पितः ६. ५८, २; ९. ८६, १४; ३९; ४५.

अर्पितं १. १६४, १२; १०. ८२, ६; १७०, २.

अर्पिता १. १४२, ९.

अर्पिताः १. १६४, ४८.

अर्बुदं २. ११, २०; १४, ४; ८. ३२, २६.

अर्बुदं १. ५१, ६.

अर्बुदस्य ८. ३, १९; ३२, २.

अर्बुदस्य १०. ६७, १२.

अर्भकः ८. ३०, १; ६९, १५.

अर्भकं १. ११४, ७.

अर्भकासः ७. ३३, ६.

अर्भके ४. ३२, २३.

अर्भकेभ्यः १. २७, १३.

अर्भगाय १. ११६, १.

अर्भस्य ७. ३७, ३.

अर्भात् १. १२४, ६; ८. ४७, ८.

अर्भा १. ५१, १३.

अर्भाय १. १४६, ५.

अर्भे १. ७, ५; ४०, ८; ८१, १; ६. ५०, ४; १०. ९१, ८.

अर्भेषु १. १०२, १०.

अर्मके १. १३३, ३[२].

अर्य ४. १६, १७; ८. १, ३४.

अर्यः १. ३३, ३; ७०, १; ७१, ३; ७३, ५; ८१, ६; ९; ११६, ६; ११८, ९; १२१, १५; १२२, १४; १६९, ६; १८४, १; १८५, ९; २. १२, ४; ५; २३, १३; १५; ३५, २; ३. ४३, २; ४. १, ७; २, १२; १८; ४, ६; १६, १९; २०, ३; २४, ८; २९, १; ३८, २; ४८, १; ५०, ११; ५. २, १२; ३३, २; ६; ९; ३४, ९; ५४, १२; ६. १४, ३; १५, ३; १६, २७[२]; २०, १; २४, ५; २५, ७; ३६, ५; ४५, ३३; ४७, ९; ४८, १६; ५१, २; ५९, ८; ७. ८, १; २१, ५; ९; ३१, ५; ३४, १८; ४८, ३[२]; ५६, २२; ६०, ११; ६४, ३; ६८, २; ८३, ५; ८६, ७; ९२, ४; १००, ५; ८. १, ४; १९, ३६; २१, १६; २४, २२; ३४, १०; ३९, २; ४८, ८; ६०, १२; ६३, ७; ६५, ९; ६६, १२; ९. २३, ३; ६१, ११; ७९, १; १०. २०, ४; २७, ८[२]; १९; ३४, १३; ४२, १; ५९, ३; ७६, २; ८६, १; ३; ८९, ३; ११६, ६; १३३, ३; १४८, ३; १९१, १.

अर्यऽपत्नीः ७. ६, ५; १०. ४३, ८.

अर्ये ८. ३३, १४.

अर्यमणः ५. ५४, ८.

अर्यमणं १. ८९, ३; १३६, ६; १७४, ६; ४. २, ४; ६. ४८, १४; ५०, १; ५१, ३; ७. ३६, ४; ३९, ५; ६६, ७; १०. ६१, १७; ६८, २; ८९, ९; ११७, ६; १४१, ५.

अर्यमणा ९. १०८, १४.

अर्यमन् ५. ६७, १; ७. ५९, १; ८. १९, ३५.

अर्यमन् २. २७, ५; ६; ८; ७. ६०, १; ८. १८, २१; ८३, ४.

अर्यमा १. २६, ४; ३६, ४; ४०, ५; ४१, १; ४४, १३; ७९, ३; ९०, १; ९; १०७, ३; १३६, ३; ५; १३९, ७; १४१, ९; १६२, १; १८६, २; २. १, ४; २७, १; २; ७; ३८, ९; ३. ५४, १८; ४. ३०, २४; ५५, ४; ५. ३, २; २९, १; ४६, ५; ६. ५२, ११; ७. ३५, २; ३८, ४; ४०, २; ४; ५१, २; ६०, ४; ५; ९; ६२, ६; ६४, १; ६६, ४; ११; १२; ८२, १०; ९३, ७; ८. २५, १३; २६, ११; २७, १७; ३१, १३; ४६, ४; ६७, २; ९४, ५; ९. ६४, २४; ८१, ५; १०. ३१, ४; ३६, १; ६४, ५; ६५, १; ९; ८५, २३; ३६; ४३; ९२, ६; ९३, ४; १२६, १; १४१, २.

अर्यमाऽइव १. ९१, ३.

अर्यमो इति १. १६७, ८.

अर्यम्णः १. ४१, ७; १०५, ६; १३६, २; ८. ४७, ९; १०. ४०, १२; १८५, १.

अर्यम्णे ४. ३, ५; ७. ६२, २; ८. १०१, ५.

अर्यम्यं ५. ८५, ७.

अर्यऽया ५. ७५, ७.

अर्यो १. १२३, १.

अर्या ७. ६५, २.

अर्ये ५. १६, ३; ८. ५१, ९; ५४, ७.

अर्वतः १. ७३, ९; ९३, १२; ११२, २२; ११८, २; १६२, ८; १२; १४; ४. ३१, ४; ३९, २; ५. ३६, २;

६. ३९, ५; ४५, १२; ४६, १; १३; ५४, ५; ६०, १२; ८. ४७, ११; ९. ६, २; ६४, ३; ७९, २; १०. ६१, १६; ७६, २.

अर्वंता १. ८, २; ११६, १७; १६२, ३; २. २, १०; ४. ३७, ६; ६. ४५, २; ८. ४०, २; ६२, ३; १०३, ५.

अर्वंताऽइव १. १५५, १.

अर्वंतां ७. १०२, २; ८. ६, ४७.

अर्वंतांऽइव ९. ४७, ५; १०. ९४, ६.

अर्वंति २. ३३, १; ८. ७१, १२.

अर्वंतीः १. १४५, ३; ७. ८७, १.

अर्वंतीभिः १०. ५, २.

अर्वंते १. ४३, ६; ६३, ५; १११, ३; १५१, ३; १६२, ६; ५. ८६, ५; ६. ३६, २; ९. ११, ३; ६२, २; १०. ४०, ५.

अर्वंत्ऽभिः १. २७, ९; ६४, १३; ७३, ९; ६. ४५, १२; ७. ९०, ६; ८. २२; ३६; १९, १०; ९२, ११; १०. ९६, ७.

अर्वंत्ऽसु ५. ८५, २.

अर्वन् १. १६३, १; ३; ४; ८; ११; ६. १२, ६.

अर्वंतः ५. ६, १; २; ७. ३५, १२; ४०, ६; ९०, ७; ९३, ३; ८. १९, ६; ९. १०, १; ६६, १०; १०. ६४, ६; ७४, १.

अर्वंतं १. ९१, २०; ११२, २१; १६२, १६; १६३, ९; ४. १५, ६; ५. ५४, १४.

अर्वंता ८. २५, २४; १०. १०५, २.

अर्वंशः १०. ९२, ६.

अर्वशेभिः १०. ९२, ६.

अर्वा १. १०४, १; १४९, ३; १५२, ५; १६३, १२; ३. ४९, ३; ४. ७, ११; ११, ४; ३६, ६; ३८, १०; ६. १२, ४; २८, ४; ३३, २; ७. २२, १; ३७, ६; ४४, ४; ५६, २३; ५८, ४; ९. ८७, ७; १०. २७, १४; ९९, ४; १३२, ५.

अर्वाक् १. ९, ५; ४७, १०; ९२, १६; १०८, ४; ११८, २; २. ३९, ३; ५; ३. ४, ८; ३२, १३; ४३, ६; ५८, २; ४. ४, ८; ३२, १५; ५. ४३, ५; ८; ४५, १०; ६२, ४; ६. १८, ११; ३७, १; ६०, ३; ६२, ११; ६३, १; ७. २७, ३; ३९, ३; ६४, २; ६७, ३; ७; ६९, ३; ७२, २; ७४, २; ८२, ८; ८३, ३; ९१, ५, ६; ८. ८, २३; ३५, २२; ६१, १; १०. १५, ४; २९, ३; ७१, ९; ७७, ४; ८९, ५; १२९, ६.

अर्वाके ८. ९, १५.

अर्वाङ् १. ३५, १०; १०४, ९; ११८, १; १५७, ३; १७७, १; २; ५; २. १८, ५; ६; ३. ४, ११; ६, ९; ३५, ६; ४१, ८; ४३, १; ४. १०, ३; ५. ४०, ४; ८३, ६; ६. १९, ९; ४१, ५; १०. १५, ९; ४४, २; ८३, ६; ८९, १६.

अर्वाचः १. १६४, १९; १६८, १; ६. ४८, ४; ७. ४८, १.

अर्वाचा ७. ७८, १.

अर्वाची १. १०७, १; २. ३४, १५; ४. ५७, ६; ७. १८, ३.

अर्वाचीनः ४. ३, २; २०, २; ३२, १४; ७. २९, २; ८. ३, १७; १०. ११६, २.

अर्वाचीनं १. ८४, ३; ३. ३७, २.

अर्वाचीनं ४. २४, १; ७. ४१, ६.

अर्वाचीना ५. ७४, ९; ८. २२, ३.

अर्वाचीनाः १०. ६, ६.

अर्वाचीनासः ६. २५, ३.

अर्वाचीनैः ९. ९७, २८.

अर्वाचः १. १६४, १९; २. २९, ६; ७. २८, १.

अर्वाचं १. ३४, १२; ४५, १०; २. ३७, ५; ३. ४१, ९; ७. ८८, १; ८. ४, १४; ६, ४५; १४, ८; ९०, ४; १०. ३८, ४.

अर्वाचा १. ४७, ८; ५५, ७; १३७, ३; २. ३९, ३; ५. ७६, १.

अर्वाणं १०. ४६, ५.

अर्वान् १. १६३, १३.

अर्वान्ऽइव ९. ९७, २५.

अर्वाऽवतः ३. ३७, ११; ८. ८२, १; ९. ३९, ५.

अर्वाऽवति ३. ४०, ९.

अर्वाऽवति ५. ७३, १; ८. १३, १५; ३३, १०; ५३, ३; ९३, ६.

अर्शसानं १. १३०, ८; ८. १२, ९.

अर्शसानस्य २. २०, ६.

अर्शसानाय १०. ९९, ७.

अर्षे ९. ६१, १५; ६५, १९.

अर्ष ९. १, ४; ४, ७; ८; ६, ३; ९, २; २०, ४; ३९, १; ४५, २; ५१, ५; ५२, १; ६२, ८; २४; ६३, १२; १६; २९; ६४, १२; ६७, ३; ७०, १०; ८५, ४; ८; ८६, ३; ८७, १; ६; ९४, ५; ९६, ८; १६; २१; ९७, ६; १५; १७; २५; ४९–५१; ९८, १; १०९, ३.

अर्षत ४. ५८, १०.

अर्षति ९. ७, ४; १८, ६; ५६, २; ७७, ४.

अर्षति १. १३५, २[२]; ९. ३, ९; ५, २; १२, ८; १३, १; १६, ४; ७; १७, ३; २०, १; २३, ५; २८, ६; ३४, १; २; ३७, १; २; ३८, १; ६; ४२, ५; ५६, १; ५७, २; ६१, १७; ६३, २०; ६५, २०; ६६, २२; ६७, ४; १५; ६९, २; ८४, २; ८६, ७; ११; १२; १६; २६; ४४; ४६; ९७, १३; १०१, ७; १०३, २; ३; १०७, ५; १७; २६.

अर्षन् ९. १६, ६; ६२, १९; ९६, २०; १०७, १५.

अर्षंति ८. ९४, ७.

अर्षंति १. १०५, १२; १२५, ५; २. २५, ४; ४. १८, ६; ५८, ५; ६; ९. २, ४; १०, ४; १३, ७; ३१, ३; ३३, ३; ३४, ६; ६२, ३; २७; ६३, ६; ६६, १३; ७७, १; ८५, ७; ८६, १; ८९, ५; १०. ७५, ४.

अर्षतु ३. ३०, ९; ८. ८९, ४.

अर्षसि ९. ३२, ४; ४४, १; ५४, ४; ६२, २३; ६४, ८; ६७, ५; ७६, ५; ७८, ५; ८०, ५; ८२, २; ८५, ५; ८६, ३५; १०७, ४; २१; २२.

अर्षात् ३. ३३, ११.

अर्हणा १. १२७, ६; १०. ६३, ४; ९२, ७.

अर्हंति १०. १५८, २.

अर्हति २. १४, २; १०. ८५, ३४.

अर्हंते १. ९४, १.

अर्हथः ४. ४७, २; ५. ५१, ६.

अर्हन् २. ३, १; ३; ३३, १०^{2}; ७. १८, २२; १०. २, २; ९९, ७.

अर्हंतः ५. ७, २; ५२, ५.

अर्हंता ५. ८६, ५.

अर्हंति ८. २०, १८.

अर्हरिऽस्वनिः १. ५६, ४.

अर्हसि १. १३४, ६^{2}; ५. ७९, १०.

अर्हसे १०. ७७, १.

अर्हांत् २. २३, १५.

अर्हामसि ४. ५५, ७.

अर्हिरे १०. ९२, ११.

अलंकं १०. ७१, ६; १०८, ७.

अलर्ति ८. ४८, ८.

अलर्पि ८. १, ७.

अलुलाऽभवंती: ४. १८, ६.

अलातृणः ३. ३०, १०.

अलातृणासः १. १६६, ७.

अलाय्यस्य ९. ६७, ३०.

अलिनासः ७. १८, ७.

अलिप्सत १. १९१, १; ३; ४.

अवं १. ११, ७; १३, ११; २४, १३; १४^{2}; १५; २५, २१; २८, १–४; ३२, २; ९; १२; ३३, ७; ५१, ७; ५४, ४; ५५, ६; ५६, १; ५७, ६; ५८, ५; ५९, ६; ७१, ५; ७९, ७; ८०, ४; ५; ८२, २; ९३, ४; १०४, ३^{2}; १०५, ३; ११६, ३; १२४, ११; १२९, ४; ६^{2}; १३०, ७; १३३, ३; ७^{2}; १५१, ६; १५२, १; १५४, ६; १६१, १०; १६४, १०; ५१; १६८, ४; ८; १७४, ४; १७९, २; १८०, २; ३; १८९, ५; २. ११, २; १४, ४; २०, ६; २७, १७; २८, ११; २९, ७; ३०, ५; ३३, ५; १४; ३४, ९; ४२, ३; ३. ४, १०; २९, ३; ५३, १९; ६१, ४; ४. १, ४; ५; ४, ५; १३, ४; ५; १६, २; १९, २; ४; २७, ३^{2}; ३०, १४; ५. २, ५; ६; ३, ९; ७, ५; २९, ४; ३०, २; १३; ३१, १२; ३२, १; ३७, २; ४१, १३; ४४, ९; ४९, ५; ५३, ८; ५६, १; ५८, ६; ६२, ३; ७८, ८; ६. ९, १; १५, १५; २५, २; २६, ५; ३०, ४; ३१, ४; ४०, १; ४७, १४; ४८, १३; १९; ५४, ३; ६१, ६; ६६, ५; ७४, ३; ७. १८, २; १७; २०; २८, ४; ३२, २७; ५८, ५; ६०, ९; ६४, २; ८६, ४; ५^{3}; ८७, ६; १०४, १७; ८. ४, ३; ६, २९; १३, २५; १४, १४; १९, २३; २४, ३०; ३५, ४; ७; ३६, २; ४७, ११; ५३, ४; ६२, ६; ६४, १; ८; ६६, १४; ६९, ९; ७०, ११; ७४, १५; ७९, ९; ८०, ६; ९२, ९; ९६, १३; १७; ९. ७, ३; ९, ७; १५, ६; ३८, ५; ७०, १०; ७१, ९; ७३, ४; ८; ९; ७४, १; ४; ६; ७; ७५, ३; ८५, २; ८६, २७; ३१; ९६, १३; ९७, ३३; १०७, १९; २२; १०. ८, ९; १६, ५; २३, २; ४; ३०, २; ३४, ५; ३९, ६; ४०, ३; ४८, ५; ६; ५०, ५; ५९, ९^{2}; ६०, ११; ६१, २०; ६५, १२; ६६, १४; ६९, ११; ७३, ६; ८६, १०; १०५, १; ८; १०८, ५; ११३, ४; ५; ७; १२८, ९; १३२, ६; १३३, २; ५; १३४, २–५; १३८, २; १४४, ३; १७१, २; १७९, १.

अव १. ७, ४; ४९, २; १०२, ३; ४; ३. ३२, १२; ३५, ३; ६२, ८; ४. ३२, ४; ५२, ६; ५. ५, ९; ३३, ७; ३५, ७; ८; ६. ४१, ५; ४६, ११; ७. ४१, ३; ८. ६, ३२; २३, १२; ३६, २; ६०, १०; ७०, ६; ८०, ४; १०. ३८, १; ८०, ७; १०२, १.

अवऽअख्यंत् १. १६१, ४; १०. २७, ३.

अवऽअतिरः १. १३१, ४^{2}.

अवऽअतिरत् १. १०१, ५.

अवऽअधुः १. १५८, ५.

अवऽअभिनत् २. ११, १८.

अवऽअसृजः ६. ४३, ३.

अवऽअसृजत् २. १२, १२; ८. ३२, २५; १०. ८५, १३.

अवऽअस्यं १. १४०, १०.

अवऽअहन् ५. ४०, ६; ९. ६१, १.

अवंशात् ७. ५८, १.

अवंशे २. १५, २; ४. ५६, ३.

अवः १. १७, १; ३९, ७; ४२, ५; ४६, १२; ११४, ९; ११९, ४; १२१, १२; १२७, ५; १५१, १; १५८, ३; २. २६, २; ३. १, १५; १७, ३; २६, ५; ३१, १४; ५८, २; ५९, ६; ४. १, २०; २५, ३; ५. ३५, २; ३; ७०, १; ६. ६, १; २६, १; ६५, ३; ७. २१, ८; ८८, ७; ८. ९, १३; १६, २; २४, २५; २७, १; ३८, १०; ४७, १; ६७, १; ७३, १; ८३, १; ९४, ८; ९७, ८; १०. २२, ७; ३५, १; २; ३६, २; ११; १००, ११; ११५, ५; ५; १३२, १८५, १.

अवः १. ८३, २; १३३, ६; १६३, ६; १६४, १७; १८; ५. ४०, ६; ६. ९, ३; ८. ४०, ८; ९. ७४, ६; १०. १७, १३; २७, २१; ६७, ४.

अवः १. ११, ५.

अवःऽदेवं ८. १९, १२.

अवःऽभिः १. ८६, ६; ११७, १९; १६७, २; १८५, १०; ११; ४. २२, ७; ४१, २; ६; ५. ७४, ६; ६. ४७, १२; ७. २०, १; ३५, १; ३६, ९; ८. २६, २; ८१, २; १०. ६, १.

अवऽकर्शयति ६. २४, ७.

अवऽक्रक्षिणं ८. १, २.

अवऽक्रामंतः ६. ७५, ७.

अवऽक्षिपन् १०. ६८, ४.

अवऽखादः १. ४१, ४.

अवऽगल्यं ६. ७५, ५.

अवऽम्रती १. १९१, २.

अवऽचक्षे ४. ५८, ५.

अवऽचाकशत् ८. ३२, २२; ९. ३२, ४; १०. ४३, ६; १३६, ४.

अवत २. ३१, २; ७. ३८, ८; ५७, ५; ८. ३०, ३; ७२, १२; १०. ३५, ११; ९७, १४; १०३, ११; १०७, ११.

अवतः ८. ४९, ६.

अर्वतं २. ४०, ५; ६. ५२, १६.

अवतं १. ८५, १०; ११; ११६, ९; १३०, २; २. २४, ४; ३. ४६, ४; ८. ७२, १०; १२; १०. १०१, ५–७.

अवतं १. ३१, ८; ३४, ५; ४७, ५; १०९, ७; ८; ११७, २३; १८१, ७; १८२, ४; २. ३१, १; ५. ४०, ७; ७. ८३, १; ५; ८. ८, २०; २१; ३५, ११; ५७, ४; ५९, ३; ५; ८५, ९.

अवऽतरं १. १२९, ६.

अवतस्थिऽवांसं ८. ९६, १४.

अवतस्यं ८. ७२, ११.

अवताः ४. ५०, ३.

अवतात् १. ११६, २२.

अवतात् ८. ३, २.

अवतान्ऽईव ८. ६२, ६; १०. २५, ४.

अर्वतां १. ७६, २; १०. ७०, १०.

अवतासः १. ५५, ८.

अर्वति २. १२, १४; ५. ८३, ४; ८. २, ३५.

अवति ७. १०४, १२; ८. ७५, १४.

अर्वतु २. ४०, ६.

अवतु ५. ८७, ६; ६. ९, ७; ५०, १३; ६१, ४; ७. ४७, २; ४८, २; ८. १, १६; १०. ९२, १३; ९७, १४; १००, १; १०२, १; १०३, ७; १८२, २.

अवत्ते ४. १७, १६.

अवऽत्सारस्यं ५. ४४, १०.

अर्वथ ४. ३६, ५; ३७, ६; ६. ६६, ८; ८. २०, २४; १०. ३५, १४; ६७, ११.

अवथ ५. ५४, १४.

अर्वथः १. ११२, २; १७; २०; २२; ५. ६३, १; ८६, १; ७. ६९, ४; ८. २२, १०.

अवदः ३. ३०, ५.

अवदत् १०. १७७, २.

अर्वदतः १०. ११७, ७.

अवंदन् १. १७९, २.

अवदन् १०. ९७, १७; १०९, १.

अवदंत १०. १०९, ४.

अवद्यऽगोहना १. ३४, ३.

अवद्यऽभिया १०. १०७, ३.

अवद्यं ४. १८, ७; ५. ५३, १४; ८. ६८, १९; १०. १४, ८.

अवद्यंऽईव ४. १८, ५.

अवद्यात् १. ९३, ५; ११५, ६; १६७, ८; १८५, १०; ३. ३१, ८; ४. ४, १५; ६. १५, १२; ७. १२, २.

अवद्यानि ६. ६६, ४.

अवद्ये ८. ८०, ८.

अवधं १. १८५, ३.

अवऽधावंति १. १६२, ११.

अर्वधीः १. ५१, ४; ८०, ११; १०३, ८; ६. २७, ४; ८. १२, २६.

अवधीः १. ३३, १२; ८०, ७; ४. ३०, १५; १८.

अर्वधीत् १. ५२, २; ५. ३४, ४.

अवधीत् १. १८७, ६; ८. ७२, ४; ९३, २; १०. १४६, ४.

अवऽधूनुषे १. ७८, ४.

अवऽधून्वानः ६. ४७, १७.

अवध्रं ७. ८२, १०.

अर्वन् ७. ४६, २.

अवन् १. २४, ३.

अर्वऽनद्धं १. ११६, २४.

अवनयः १. १८६, ८; १९०, ७; ५. ८५, ६.

अवना ५. ५४, २.

अवनिः १. ४, १०; १८१, ३.

अवनिं १. १४०, ५; ४. १९, ६.

अवनीः १. ६१, १०; ६२, १०; २. १३, ७; ५. ११, ५; ६. ६१, ३; ७. ८७, १; १०. ९९, ४.

अर्वऽनीतं १. ११६, ८.

अर्वऽनीताय १. ११८, ७.

अर्वनोः ५. २९, ९.

अवनोः ६. १८, ३; १०. ६९, १०.

अर्वंतं ८. ७३, ७.

अर्वंति १. १७९, ३; २. २३, १९; २४, १६; ३५, १५; ९. ८३, २.

अवंति ४. ५०, ९.

अर्वंती इति १. १८५, ४.

अर्वंतीः १. १५२, ६; ७. ४६, २.

अर्वंतु १. १०६, ३; ५. ४२, ५; ६. ५२, ४; ८. ५४, ४.

अवंतु १. २२, १६; २३, १२; १२७, २; ३. ८, ८; १०; ६२, ३; ४. ३१, १०; ३३, ३; ५. ४१, ११; ४६, ७; ५१, १३; ८७, ७; ६. ५०, १४; ६९, २; ७. ३६, ७; ४९, १; ८. ३, १; ६३, १२; १०. १५, १; ५; ७७, ८.

अवन्वन् १. ५१, २.

अर्वपत् २. १४, ७.

अवपत् १०. ७३, ५.

अवऽपतंतीः १०. ९७, १७.

अवऽपदः २. २९, ६.

अवऽपश्यन् ७. ४९, ३.

अवऽपाने ७. ९८, १; ८. ४, १०; १०. ४३, २.

अवऽपानात् १०. १०६, २.

अवऽपानेषु १. १३६, ४.

अवऽभृथं ८. ९३, २३.

अवमः ४. १, ५.

अवमं १. १०५, ४; ७. ३२, १६.

अवमस्यं ६. २१, ५.

अवमस्यां १. १०८, ९; १०; ७. ७१, ३.

अवमा ३. ५४, ५; ६. २५, १; १०. ८१, ५.

अवमाभिः ६. ६२, ११.

अवमायं २. ३५, १२.

अवऽमार्जनानि १. १६३, ५.

अवमीत् ४. ५८, २.

अवमे १. १०१, ८; ५. ६०, ६.

अवमे इति १. १८५, ११.

अवमैः ३. ३०, १६.

अवऽयती ८. ९१, १.

अवऽयाः १. १७३, १२.

अवयातऽहेळाः १. १७१, ६.

अवऽयाता १. १२९, ११; ८. ४८, २.

अवऽयातां १. ९४, १२.

अवऽयानं १. १८५, ८.

अवयुनं ६. २१, ३.

अवऽयै ८. ४७, १२.

अवरः १. १६३, ९; १०. ८८, १७; १९.

अवरं १. १५५, ३; १६८, ६; १०. ५५, ४; ८६, ३; १२०, ७.

अवऽरंबमाणः ८. १, ३४.

अवराणि ८. ९६, ६; ९. ९६, ७.

अवरात् ७. ६, ७.

अवरान् २. ३४, १४; ८. ७५, १५; ९. ९७, १७; १०. ८१, १.

अवरासः ६. २१, ६.

अवरासु १. १४१, ५.

अवरित्यव: ५. ३१, ३.

अवरीवरिति १०. १२९, १.

अवरीवुरिति १०. ५१, ६.

अवंऽरुद्धः १०. २८, १०.

अवरे २. ९, ३; १२, ८; २४, ११; ४. २५, ८; १०. १५, १.

अवरेण १. १६४, १७; १८; ४३; ६. ९, २.

अवरेषु १०. ५६, ६; ७.

अवऽरोधनं ९. ११३, ८.

अवऽरोहन् ५. ७८, ४.

अवर्त् ७. ५९, ४.

अवर्तत १०. ९०, १४; १२१, १; ७; १२९, ४; १३५, ४.

अवर्तत ५. ३१, ५.

अवर्तयः ५. ३०, ७; १०. १३५, ४.

अवर्तयः १. १२१, १३; ८. १४, १३.

अवर्तयत् १. ८५, ९; २. ११, २०; ८. १४, ५.

अवर्तयत् ६. ८, ३; १०. १३५, ५.

अवर्ति १. ११८, ३; ५. ७६, २.

अवर्त्या ४. १८, १३.

अवत्रैः ६. १२, ३.

अवर्धत १. ३३, ११; २. १७, ४; ९. ७०, १; १०. ९६, ८.

अवर्धत ९. ४७, १; १०. ११३, १.

अवर्धतां १०. १३२, १.

अवर्धन् ३. ३२, ३; ३५, ९; ४७, ४; १०. ७३, १; ३; ११३, ३.

अवर्धन् ५. २९, ११; ३१, १०; १०. ४५, ३; ९५, ७.

अवर्धत १. ८५, ७; १०. ६, ७.

अवर्धयः २. ११, १५; १०. १३८, २.

अवर्धयत् ८. १२, ७.

अवर्धयत् ८. १४, ५.

अवर्धयन् ३. १, ४; ५. ३१, ४; १०. ९५, ७; ११३, ८.

अवर्धयन् ५. ११, ३; ८. १३, १७; ४१, ३.

अवर्षीः ५. ८३, १०.

अवर्षीत् ७. १०३, ३.

अवंऽविद्धं १. १८२, ६; ७. ६९, ७.

अववृत्रन् १. १६४, ४७; ३. ३२, १५; १०. १८, ३.

अववृत्रंत ४. २४, ४.

अवऽव्ययंन् ४. १३, ४.

अवशत् २. २२, १.

अवसः २. ४, ८; २७, ५; ३. ५१, ६; ४. २१, १०; ५. २२, ३; ५७, ७; ८. ७५, १६; ९. ५८, २.

अवसत् १. १४४, २.

अवसं १०. ९५, १६.

अवसं १. ९३, ४; ११९, ६; ६. ६१, १.

अवसा १. १७, ६; २२, ११; २४, ५; ३९, ७; ७७, ४; ८५, ११; ८९, ७; १०२, ५; १०७, २; ११०, ७; १२४, १३; १३८, ३; १५२, ७; १६६, २; १७७, १; ५; १८५, ४; ६; ९; १८७, ६; ३. ३२, १३; ५. ४२, १८; ४६, ६; ४९, ५; ७६, २; ३; ६. २, ११; २०, १०; ३१, ५; ५०, ९; ५२, ५; ६; ५९, ३; ७. २१, ९; ५१, १; ८२, ८; ८३, १; ३; ९४, ७; ८. ६१, ४; ९. ६१, २४; ९८, ८; १०. १५, ४; ३५, १३; ४०, ७; ६४, ९; ८९, १६; १२०, ७; १२१, ६.

अवऽसातारं १०. २७, ९.

अवऽसानं १०. १४, ९.

अवसानाः ३. १, ६.

अवसां ४. २३, ३.

अवसायं १०. १६९, १.

अवऽसायं १. १०४, १.

अवसि ५. ६५, ५; ६. २३, २; ५८, १; ८. ३६, ३; ३७, ६; ४७, ५.

अवसि १०. १४०, २.

अवऽसितस्य १. ३२, १५.

अवऽसितासः ४. २५, ८.

अवसिष्ट ९. ८९, २.

अवऽसृजन् १. १४२, ११; २. ३, १०.

अवऽसृष्टः १०. ४, ३.

अवऽसृष्टा ६. ७५, १६; ७. ४६, ३.

अवऽसृष्टान् १०. २८, ११.

अवऽसृष्टासः १०. ९१, १४.

अवसे १. १७, २; २२, ६; १०; ३४, १२; ३५, १; ४५, ५; ४७, १०; ४८, १४; ५२, १; १२; ८९, ५; १००, ८; १०२, १०; ११२, २४; ११४, ४; ११८, १०; १२७, ४[२]; १२८, ८; १२९, १०[२]; १३५, ४; १६४, ५२; १६८, १; १८३, ५; १८६, १०; २. १२, ९; १६, १; २९, १; ३४, १४; ३. १३, २; २६, २; ४७, ५; ५४, १२; ५७, ५; ६२, २; ४. २, १३; ३, १; २०, १; २; २१, १; ३; २५, १; ४१, ७; ८; ५. १७, १; २५, १; ३५, १; ४१, ५; ४५, ४; ६५, ३; ६. १४, १; ३; १७, १३; २१, ९; २३, ८; ९; २४, १०; २९, १; ३३, २; ३८, ५; ४०, ५; ४६, ६; ४८, ४; ६१, २; ७. १, २; २१, ८; २६, २; ३२, ८; ३८, ६; ४८, ४; ५१, २; ७४, १; ८५, ४; ९०, ७; ८. ८, ६; ९; ९, १; ११, ६; ९; १२, १९; १९, ३२; २२, ३; १६; २३, २५; ३२, १०; ३४, ४; ५३, ७; ५४, २; ३; ७; ६१, ८; ६३, ४; ७०, २; ७१, १४; ८६, ४; ९९, ८; ९. १०८, १४; १०. ३१, १; ३८, ४; ३९, ५; ६३,

११; ६६, ४; ७४, ५; ८१, ७; १०१, १; १४१, ३; १४९, ५.

अवऽसै ३. ५३, २०.

अवस्तात् ३. २२, ३; १०. ८८, १४; १२९, ५.

अवस्थाः ३. ३२, ११.

अवऽस्थाः ५. १९, १.

अवऽस्परत् ६. ४२, ४.

अवऽस्पर्तः २. २३, ८.

अवस्यते १. ११६, २३.

अवस्यवः १. १४, ५; १०१, १; ११४, ११; १३१, ३; २. ११, १२; १३; १९, ८; २१, ५; ३. ४२, ९; ७. ९४, ४; ८. १३, १७; २१, १; ६३, १०; ९. १७, ७; ६३, २०; ८६, २४.

अवस्यवः ९. १३, २.

अवस्यवे २. ६, ६; ४. ५०, ९.

अवस्युः १. २५, १९; ३. ३३, ५; ४. १६, ११; ५. ३१, १०; ७. ३२, १७; ८. ३५, २२.

अवस्युऽभिः ८. १३, ९.

अवस्युं ५. ७५, ८.

अवस्युवः ९. ४३, २.

अवस्युवं ५. ४६, १.

अवस्रन् ४. २, १९.

अवऽस्रसः २. १७, ५.

अवहः २. १३, ८; ५. ३१, ८; ८. २४, २८.

अवहः १. ५१, २.

अवहत् ३. ५३, ९; १०. ५९, १०.

अवहत् १०. २९, २.

अवहन् १. ५१, १०; ४. ३३, २; १०. ८५, ३८.

अवऽहंता ४. २५, ६.

अवऽहितः १. १०५, १७.

अवऽहितं १०. १३७, १.

अवांसि ४. ५५, ५; ७. ९७, २; ८. २६, २१.

अवाः १. २७, ७.

अवाचः ४. २५, ६.

अवाचि १. ५१, १५; ५. ३, १२; ६. ३४, ५; ७. ७०, १; ८. ४०, १२; १०. ५४, ६.

अवाजिनं ३. ५३, २३.

अवाट् १०. १५, १२.

अवातः ६. १६, २०; १८, १; ९. ८९, ७; ९६, ८; ११.

अवातः ८. ७९, ७.

अवातं १०. १२९, २.

अवाता ६. ६४, ५.

अवाताः ६. ६७, ७.

अवाताः १. ५२, ४; ६२, १०.

अवातां १. ३८, ७.

अवाते ६. ६४, ४.

अवाथ ७. ४०, ३.

अवाथः ७. ६१, २.

अवादिषुः ७. १०३, १.

अवामि १०. १२४, ४.

अवारत्तः १०. ६५, ६.

अवारयेथां १. ११६, ८.

अवारि ४. ६, ७.

अवार्यऽक्रतुं ८. ९२, ८.

अवावचीत् १०. १०२, ६.

अवावरीत् ८. १००, ७.

अवावशंत ९. १९, ४; ६६, ११.

अवावशंत ९. ९०, २.

अवावशीतां १. १८१, ४.

अवाशयः १. ३१, ४.

अवासयः ६. १७, ५.

अवासयः ३. १, १७.

अवासयत् १. १६०, २; ६. २२, २.

अवासयत् ३. ७, ३.

अवासयन् ७. ९१, १.

अविऽअनत् १०. १२०, २.

अविंऽउप्ताः २. २८, ९.

अविः ९. ७८, १.

अविका १. १२६, ७.

अविऽक्रीतः ४. २४, ९.

अविक्षत १०. १३६, २.

अविक्षत १. १९१, ४; १०. १२७, ५.

अविऽक्षितं ८. ३२, ८.

अविऽक्षितासः ७. १, २४.

अविक्ष्महि १०. १२७, ४.

अविऽचाचलिः १०. १७३, १; २.

अविऽचेतनानि ८. १००, १०.

अविऽचेतसः ९. ६४, २१.

अविंऽजानन् १. १६४, ५.

अविजे १०. ५१, ६.

अविड्ढि २. १७, ८.

अविड्ढि १. ११०, ९; २. २४, १; ३०, ८; ४. ३१, १२; ६. ४४, ९; ८. ९२, १५.

अवित ७. ५९, ६.

अवितरिति १. १२९, १०.

अवितवे ७. ३३, १.

अविता १. ३६, २; ४४, १०; ८१, ८; ९१, ९; १८७, २; २. १२, ६; ३. १९, ५; ६२, ९; ४. १६, १८; २०; १७, १८; ३१, ३; ५. ४, ९; ६. ३३, ४; ३४, ५; ४४, १५; ४५, ५; ४६, ४; ४८, २; ७. १९, १०; २४, १; ३२, १०; ११; ९६, ५; ८. २, ३६; ४, १८; १३, १५; २६; ३६, १; ४६, १३; ८०, ३; ९. ६७, १०; १०. ७, ७; २४, ३; १०३, ४; १५७, ३.

अविताऽइव ८. ७१, १५.

अवितारं ६. ४७, ११; ७. ३६, ८; ८. २१, २.

अवितारा १. १८१, १.

अवितारा १०. ३९, ३.

अविऽतारिणीं ८. ५, ६.

अवितुः ७. २५, ४.

अवित्री ६. ६१, ४; ७. ९६, २.

अवित्री इति २. ३२, १.

अवित्सि १०. १५, ३; ९७, ७.

अविथुराः १. ८७, १.

अविदुः ५. ८३, १०.

अविदत् १. ५३, १; ६. ४४, ७.

अविदत् १. ९२, ९; ३. ५७, १; ६. ६३, १; ७. ८९, ४; ८. ९१, १; १०. ५, ५; ७९, ३.

अविदन् १०. ९४, ३.

अविदन् १. ७२, ६; १०. ९४, ४.

अविदं १०. १६१, ५.

अविदं १०. १६१, ५.

अविऽदुस्यं ७. ३९, ६.

अविदाम ८. ४८, ३.

अविदाम १०. १०, १३; ५३, ३.

अविंऽदीधयुं ४. २१, ७.
अविंदुःऽतरासः १०. २, ४.
अविद्रियाभिः १. ४६, १५.
अविंद्वांसः ६. १५, १०.
अविंद्वान् १. १२०, २; ५. ३०, ३; १०. ७९, ६.
अविंधत् १. १३६, ५; २. १, ७; ९; २६, ४; ६. ५४, ४; ८. २३, २१; २७, १५; ६१, ९; ९. ११४, १; १०. ८३, १.
अविधवाः १०. १८, ७.
अविंध्यत् ५. ४०, ५.
अविध्यत् १. ३३, १२; ८. ३२, २६; ७७, ६.
अविंदः १. ६, ५; ६. ७, ५.
अविदुः ६. ६१, ३; ८. ९६, १६; १७.
अविंदत् १. ३३, १४; १०१, ५; १३०, ३; ३. ३४, ४; ५. १४, ४; २९, ३; १०. ४३, ८; १०८, ११.
अविंदत् १. १०३, ५[२]; ५. ४०, ६; ४५, ७; १०. ४६, ३; ६७, १; ६८, ९; १०९, ५; १३९, ६.
अविंदतं १. ९३, ४.
अविंदन् १. ६२, २; ३. १, ३; १०. ६२, २; १८१, २.
अविंदन् ३. ९, ४; ३१, ५; ४. ५८, ४; ५. ११, ६; ४०, ९; ७. ७६, ४; १०. ४६, २; ७१, ३; १११, ७; १२९, ४; १८१, ३.
अविंदंत १. ८३, ४.
अविंदेथां ४. २८, ४.
अविप्रः ८. ६१, ९.
अविप्रे ६. ४५, २.
अविंऽभिः २. ३६, १; ९. ८६, ११; ९१, २; १०७, २.
अविंऽमान् ४. २, ५.
अविंऽरणाय १. १७४, ८.
अविंविक्तां १०. ११२, ४.
अविंवेः ६. ३१, ३.
अविंऽवेनन् ४. २४, ६.
अविंऽवेनं ४. २५, ३.
अविंवेशीः ३. ३२, १०.
अविंवेपीः ४. १९, १०; २२, ५.
अविवेपीः ७. १९, ५.
अविव्यक् ७. १८, ८.
अविव्यचुः १०. ५६, ४.
अविंशत् २. २४, २; ९. ३८, ५.
अविशत् १. १४१, ५; २. १३, १.
अविशंत १०. ४४, ६; ५५, २.
अविऽशस्ता १. १६२, २०.
अविंश्रन् ८. २७, १२.
आविंश्वऽमिन्वं २. ४०, ३.
आविंश्वऽमिन्वां १. १६४, १०.
अविपः ३. १३, ६.
अविपत् १. ८१, १.
अविपस्यं ८. २५, २०.
अविपा ६. ३९, ५.
अविष्टनं ७. १८, २५.
अविंष्टं ८. ५, १३.
अविष्टं ४. ५०, ११; ७. ६७, ६.
अविष्टुं २. ३०, ६; ५. ६२, ९; ७. ६७, ५; ८. ९, ५.
अविष्टां १. १८५, ९; ५. ४३, २.
अविष्टु १. १११, ५; १०. २६, १; ९.
अविंष्टो इतिं ७. ३४, १२.
अविंष्टः ७. २८, ५.
अविष्यते १०. ११५, ६.
अविष्यन् १. ५८, २; ७. ३, २.
अविंष्यंतं ८. ५१, ३.
अविष्यवंः ८. ४५, २३.
अविष्यवः ८. ६७, ९.
अविष्यवें १. १८९, ५.
अविष्यां २. ३८, ३.
अविहर्यतक्रतो इत्यविहर्यतऽक्रतो १. ६३, २.
अविंऽह्रुतं ५. ६६, २; १०. १७०, १.
अविंऽह्वरंतं ४. ३६, २.
अवीः ६. १०, ६.
अवींत् ७. ३४, १४.
अवींताः ४. ४८, १.
अवींनां ९. १०७, ८; १०९, ७; १०. २६, ६.
अवीरंता ७. १, ११.
अवीरंतायै ३. १६, ५.
अवीरंते ७. १, १९.
अवीरयेथां १. ११६, ५.
अवींरऽहा १. ९१, १९.
अवीराः ७. ४, ६; ६१, ४.
अवीरांऽइव १०. ८६, ९.
अवीरें १०. ९५, ३.
अवीवतन् १०. १३, ५.
अवीवशत् ९. ३२, ३; ३४, ६; ७६, ४; ८६, १९; १०७, २६.
अवीवशन् ९. २१, ७.
अवींवशंत १०. ६४, १५.
अवीविपत् १. १५५, ६; ९. ९६, ७.
अवीविपन् ९. ७३, २.
अवीवृतत् १०. १७४, ३.
अवींवृधत् ८. ८, १५; १९; ८०, १०.
अवीवृधत् ८. ८, ८; १०. ६३, १७.
अवींवृधध्वं १. १२४, १३.
अवींवृधन् ७. ३६, ७.
अवीवृधन् १. ५, ८; ११, १; ९. ४, ९; ७३, २.
अवींवृधंत ४. ३२, १२.
अवृकः ४. १६, १८; ६. २, २; १५, ३.
अवृकऽतंमः १. १७४, १०.
अवृकं १. ४८, १५; ६. ४८, १८; ७. ८८, ५; ८. ९, १; २७, ४; १०. ३६, ३; १४४, ५.
अवृकस्यं १. १५५, ४.
अवृकाः ४. ४, १२; १०. १५, १.
अवृकाणिं १. ५५, ६.
अवृकाभिः २. ३१, ३.
अवृकायं १. ३१, १३; ७. ६६, ८.
अवृकासः ७. ७४, ६.
अवृके ६. ४, ४.
अवृकेभिः ६. ४, ८; ७. १९, ७.
अवृक्त ८. १०१, १६.
अवृक्षं १०. १५९, ५.
अवृजन् १०. ४८, ३.
अवृंजिनाः २. २७, २.
अवृंजन् ३. ५६, ४.
अवृंणक् १. १०१, २; २. १४, ७; १७, ६.
अवृणक् १. ५३, ९; ५. २९, १०; ३२, ८.
अवृणि १०. ३३, ४.
अवृंणीत २. ३३, १३; ४. ४३, २; ९. ९७, ४१.

अवृणीत १. ३२, ३; ११७, १३; ११९, ५; ३. ३६, ८; ७. ३३, २; ६९, ४; ९. ७०, ६; १०. १३, ४^{2}; ८५, १४.

अवृणीतं १. १८०, ४.

अवृंणीमहि ३. २९, १६.

अवृंणोः १. १३२, ४.

अवृणोः १. ५१, ३; ४; २. ११, १८; ९. ८६, २३.

अवृणोत् १. १३०, ३; ३. ३१, २१; ३४, ३; ४४, ५; ४. २८, १; ८. ६३, ३; १०. १३९, ६.

अवृण्वत २. ३४, १.

अवृत ५. ४५, १.

अवृंतः १. १३३, ७; ६. १४, ५^{2}; ८. ३२, १८; ३३, ६; १०.

अवृंतं ८. १०२, १४.

अवृंत्रन् ८. ९२, १४.

अवृत्सत ५. ५५, १; ८. १, २९.

अवृधत् ४. २३, १.

अवृधान् ७. ६, ३.

अवृंश्चत् १०. ११३, ४; ६.

अवृश्चत् ७. १८, १७.

अवृहः ५. २९, १०.

अवेंः ८. २१, १२.

अवेंत् ५. ३४, ८; ६. ४७, १५.

अवेदं ४. २७, १.

अवेदि ७. ८, २; १०. ९९, १०.

अवेंन १. १२८, ५.

अवेंनत् ४. ३३, ६.

अवेनत् ४. १८, ११.

अवेंनंतं १०. २७, १६.

अवेपयः ८. ७६, १०.

अवेपन् १. १७८, २; १०. ११४, १.

अवोः ६. ६७, ११; ७. ६७, ४; १०. १३२, ५.

अवोंचत् १०. १२०, ९.

अवोचत् ८. १००, ५.

अवोंचन् १. १८२, ८; १०. १०९, ३.

अवोचन् १. ११७, २५; १२२, १२; ५. २, १२; १०. ११५, ९.

अवोंचंत ६. ३१, १.

अवोचं १. ११६, २५; १८५, १०; ४. ४५, ७.

अवोंचाम १. ७८, ५; ११४, ११; १८९, ८; ४. २, २०; ५. १, १२; ७३, १०; ८. ५९, ५.

अवोचाम १०. ८०, ७.

अव्यंः ८. २, २; ९. ६, १; ७, ६; १२, ४; १६, ८; २०, १; २८, १; ३८, १; ५०, ३; ५२, २; ६३, १०; १९; ६८, ७; ७४, ९; ८६, ४८; १०१, १६; १०६, १०; १०७, ६; १०८, ५.

अव्यत् २. ३८, ४.

अव्यंत १. १६६, ४.

अव्यत ९. ८, ६; ६९, ४; ९७, १२; ९८, २; १०१, १४; १५; १०७, १३; १८.

अव्यंत्यै १०. ९५, ५.

अव्यथिः १. ११७, १५; ९. ४८, ३.

अव्यथिऽभिः १. ११२, ६; ७. ६९, ७.

अव्यथिषुः ८. २, २४.

अव्यथी १०. २७, २१.

अव्यथीः १०. ३१, १०.

अव्यथ्यायं २. ३५, ५.

अव्यंन् ३. ४९, १.

अव्यं ९. १३, ६; ६१, १७; ६७, ५; ६९, ९; ९७, ४; ५६; १०७, १७; १०९, १६.

अव्ययत् २. १७, ४.

अव्ययं ८. ९७, २.

अव्ययं ९. ३७, ३; ४९, ४; ६६, २८; ६७, २०; ६९, ४; ८२, १; ८५, ५; ८६, ८; ३१; ९८, २; १००, ४.

अव्ययं ७. ३३, ४.

अव्यया १. १३५, ६^{2}; ९. ६२, ८; ६७, ४; १०३, २; १०७, १०.

अव्ययानि ९. ८६, ३४.

अव्ययीं ९. ७०, ७.

अव्यये ९. १६, ६; ३६, ४; ६४, ५; ६६, ११; ८६, ३; ९९, ५; १०३, ३; १०७, २२; ११०, १०.

अव्या ९. ७५, ४; ८८, ६.

अव्याः २. ३८, १०; १०. १३९, ५.

अव्यान् ९. ९७, ३१.

अव्ये ९. ५०, २; ६६, ९; ६९, ३; ७०, ८; ८६, १३; २५; ९१, १; ९२, ४; ९६, १३; ९७, ३; १२; १६; १९; ४०; ९८, ३.

अव्रतः ८. ९७, ३.

अव्रतं १. १०१, २; १३२, ४^{2}; १७५, ३; ६. १४, ३; ९. ४१, २.

अव्रतान् १. ३३, ५; ५१, ८; १३०, ८; ९. ७३, ५; ८.

अव्रंदंत २. २४, ३.

अव्रन् ४. ५१, २.

अव्रि ४. ५५, ५.

अशंसन् १. ६७, २.

अशंसिषं ४. ३, १६.

अशंसिषं १०. १४६, ६.

अशंसीत् ८. ८, ११.

अशंक्नुवन् ५. ४०, ९.

अशत्रु ५. २, १२.

अशत्रुः १. १०२, ८; १०. १३३, २.

अशत्रुऽभ्यंः ८. ९६, १६.

अशत्रुं १०. २८, ६.

अशत्रो इर्ति ८. ८२, ४.

अशनिंः १. १४३, ५; १७६, ३; ४. १६, १७; ६. ६, ५; १८, १०; ८. २७, १८; १०. ८७, ५.

अशनिंऽभिः १०. ८७, ४.

अशनिं १. ५४, ४; ८०, १३; ३. ३०, १६; ७. १०४, २०; २५.

अशनिंमान्ऽइव ४. १७, १३.

अशन्याऽइव २. १४, २.

अशंपत १. १६१, १२.

अशंमिष्ट ५. २, ७.

अशमिष्टाः ३. २९, १६.

अशंयत् ८. ६, १६; ९. ७१, ८.

अशयत् १. ३२, ७; १०; ५२, ६; ३. १, ११; ७. १८, ८.

अशयिष्टाः १०. १२४, १.

अशसः २. ३४, ९; ४. ४, १५.

अशंस्तऽवारः १०. ९९, ५.

अशंस्ति १०. १८२, १.

अशस्तिऽहा ८. ८९, २; ९९, ५; ९. ६२, ११; ८७, २; १०. ५५, ८.

अशंस्तीः १. १००, १०; ४. ४८, २; ६. ४८, १७; ६८, ६; ७. १८, ५.

अशान १. १७०, ५; ३. २१, १.
अशायः ६. ३३, २.
अशायत ८. ७३, ९; १०. ४३, ६; ९२, १.
अशायतं १. ३४, ७.
अशासत ९. १०२, ४.
अशांसं १०. ९५, ११.
अशास्यं ८. ३३, १७.
अशिक्षः ६. ३१, ४; १०. ५४, १.
अशिक्षतं १. ११२, १९.
अशिक्षतं ७. ८३, ८.
अशिपदाः ७. ५०, ४.
अशिमिदाः ७. ५०, ४.
अशिवः १०. १२४, २.
अशिवस्य १. ११७, ३; ६. ४४, २२.
अशिवा १०. २३, ५.
अशिवाः ५. १२, ५.
अशिवासः ७. ३२, २७; १०. ९५, १५.
अशिवेन १. ११६, २४; ११७, १७.
अशिशात् ७. १८, २४.
अशिश्नत् ७. २८, ३.
अशिश्रयुः ७. २, ५.
अशिश्रयुः १. ९२, २; ९. ११, २; ८६, १७; १०. ७६, ३.
अशिश्रेत् ३. ३८, ८.
अशिश्वितत् ८. ५, १.
अशिश्वीः १. १२०, ८; ३. ५५, १६.
अशीत् १०. ८७, १७.
अशीत्या २. १८, ६.
अशीमहिं ५. ४७, ७.
अशीमहि ७. ३२, २६; १०. ३६, ४; ३७, ६; ४०, १२.
अशीय २. ३३, २; ६.
अशीर्षा ४. १, ११.
अशुचत् ७. ९, ४.
अशुश्रवि १०. ४८, ८.
अशुश्रवुः १०. ९४, १२.
अशुषे १. १०१, २; १७४, ३; २. १४, ५; १९, ६; ४. १६, १२; ६. ३१, ३.
अशुषस्य ६. २०, ४.
अशुशुभन् ९. ६२, ६.
अशृणवं १०. ८८, १५.
अशृणात् १०. १३८, ४.
अशृणोः ७. २९, ४; ८. ३६, ७; १०. १७१, १.
अशृणोः १०. ९५, ११.
अशृथिताः १०. ९४, ११.
अशेम १. २४, ५; ८९, ८; ५. ३०, २.
अशेरन् १. १३३, १.
अशेवा ७. ३४, १३.
अशेवाः १०. ५३, ८.
अशेपसः ७. १, ११.
अशोचत् ३. २९, १४.
अशोचि ७. ६७, २.
अशोचि ७. ८, १.
अश्नः १. १६४, १; १७३, २; १०. २७, १५.
अश्नते ९. ५१, ३.
अश्नन् १०. १७६, १.
अश्नंता ७. ६७, ७.
अश्नंतौ ८. ५, ३१.
अश्नं २. १४, ५.
अश्नवत् १. १, ३; ४०, ६; ७; ९३, ३; ११३, १८; २. २३, ४; ५. ५९, ४; ८. १८, १४; ९. ६६, २७.
अश्नवन् ८. ९०, ६.
अश्नवंत ७. ३०, ४.
अश्नवाम ६. ४९, १५; ९. ९७, ५१.
अश्नवामहै १०. ९७, १७.
अश्नवाव १. १७९, ३.
अश्नवैथे इति ७. ७०, ४.
अश्नस्य २. २०, ५; ६. ४, ३.
अश्ना ४. २८, ५; १०. ६८, ८.
अश्नाऽइव २. ३०, ४.
अश्नाति ९. ६७, ३१; १०. ८५, ३; ४.
अश्नीतं ७. ७३, २.
अश्नुतः ८. ३१, ८.
अश्नुतं ८. ४०, ३; १०. ८५, ४२.
अश्नुते ६. २८, ४; ८. ५१, ६; ९. ८३, १.
अश्नुथ ५. ५४, १०.
अश्नुवते ७. १०३, ९.
अश्नुवन् १. ११६, २५.
अश्नुवंति ७. २२, ८; ९९, १.
अश्नुवंतु ६. २३, ८; ७४, १.
अश्नुवे १. १६४, ३७.
अश्नुषे ९. ६५, ६.
अश्नुहि १. ५४, ९; ८. ४५, २२; ८२, ६.
अश्नैः ८. २, २.
अश्नोति १. ९४, २; २. १६, ३; २४, ८; ३. ११, ७; ५९, २; ९. ८१, २; १०. ३९, ११; ६२, ९; ६४, १५.
अश्नोतु १. १७, ९; ३. ५१, १२; ४. ९, ८.
अश्मंऽआस्यं २. २४, ४.
अश्मंऽचक्रं १०. १०१, ७.
अश्मंऽदिद्यवः ५. ५४, ३.
अश्मंन् ७. ८८, २.
अश्मंनः २. १, १; ३. २९, ६; ६. ४३, ३; ९. १०८, ६; १०. ६८, ४.
अश्मंना १. १९१, १५.
अश्मंनि १. १३०, ३[२]; २. २४, ७.
अश्मंनोः २. १२, ३.
अश्मन्ऽमयानि १०. ६७, ३.
अश्मन्ऽमयींनां ४. ३०, २०.
अश्मन्ऽमयींभिः १०. १०१, १०.
अश्मन्ऽवती १०. ५३, ८.
अश्मंऽभिः ९. ११२, २.
अश्मंऽव्रजाः ४. १, १३.
अश्मंऽव्रजानां १०. १३९, ६.
अश्मंहन्मऽभिः ७. १०४, ५.
अश्मा १. १७२, २; ५. ४७, ३; ६. ७५, १२.
अश्माऽइव १०. ८९, १२.
अश्मानं १. १२१, ९; २. ३०, ५; ४. १६, ६; २२, १; ५. ३०, ४; ८; ७. १०४, १९.
अश्याः १. ६०, ३; ६९, ३; ७०, १; २. ३१, ७; ४. ५, ७; ५. ४२, १, १४–१६.
अश्यां ५. ६४, ३.
अश्यां १. ९२, ८; १५४, ५; १६६, १४; १७८, १; २. २७, ११; १४; ३. ५४, २१; ५७, २; ५. ४, १०; ६. १, १३; १३, ६.
अश्यामं १. ११४, ३; २. १९, ७; २७, १०; ६. ५, ७[४]; ७. ६५, २; ८. २७, २२; ९. ९८, १२.
अश्याम १. ११४, २; १३६, ७; ३. ११, ८; ४. ४, १४; ५८, ११; ५. ४१, १८; ७०, २; ७. ४७, २; ९३, ८; ९. ९१, ५.

अश्युः १. ७३, ५: ९; २. १९, ८.

अश्रथयः १०. ११२, ८.

अश्रथ्नन् २. २४, ३.

अश्रद्धान् ७. ६, ३.

अश्रमणाः १०. ९४, ११.

अश्रमासः ६. २१, १२.

अश्रमिष्ठाः ४. ४, १२.

अश्रमैः ७. ६९, ७.

अश्रवं १. १०९, २.

अश्रवं १०. ८६, ११.

अश्रवयं १०. ४९, ८.

अश्रान्तः १०. १७९, १.

अश्रान्ताः १०. ६२, ११.

अश्रायि ६. ११, ५.

अश्रायि १. ५१, १४.

आश्रितं ४. ७, ६.

अश्रियन् ८. २, ३९.

अश्रीणीत १०. ६१, ३.

अश्रीरःऽइव ८. २, २०.

अश्रीरं ६. २८, ६.

अश्रीरा १०. ८५, ३०.

अश्रु १०. ९५, १२; १३.

अश्रेः ३. ५४, ११.

अश्रेः ५. ३३, २.

अश्रैत् ७. ३, ४; १०. ७६, ३.

अश्रेत् १. ९२, ५; १२४, १; ३. १४, १; १९, २; ६१, ५; ४. ६, २; १३, २; ५. १, १२; २८, १; ७. १०, १; ३९, १; ६२, १; ७६, १; ७९, १.

अश्रोत् १. ३९, ६; ७. ३३, ५.

अश्वऽअजनि ६. ७५, १३.

अश्वंऽइषितं ८. ४६, २८.

अश्वः १. ३६, ८; १६१, ३; १६२, २२; १६४, २; १७३, ३; ३. २६, ३; २७, १४; २९, ६; ४. २, ८; ६. ३, ४; ४५, २६; ७. ३, २; ७०, १; ८. २, २; ४९, ५; ९. ६४, ३; ७१, ६; ९७, २८; १०१, २; १०९, १०; ११२, ४; १०. ६१, २४; १३६, ५.

अश्वऽचंद्राः ६. ३५, ४.

अश्वऽजित् ९. ५९, १.

अश्वऽजिते २. २१, १.

अश्वत्थं १. १३५, ८.

अश्वत्थे १०. ९७, ५.

अश्वथः ६. ४७, २४.

अश्वऽदाः १. ११३, १८; ५. ४२, ८; १०. १०७, २.

अश्वऽदातरः ८. ७४, १५.

अश्वऽदावन् ५. १८, ३.

अश्वऽनिर्निजि १०. ७६, ३.

अश्वऽपते ८. २१, ३.

अश्वऽपर्णाः ६. ४७, ३१.

अश्वऽपर्णैः १. ८८, १.

अश्वऽपस्त्यं ९. ८६, ४१.

अश्वऽपृष्ठं ८. २६, २४.

अश्वऽपेशसं २. १, १६; २, १३.

अश्वऽबुध्नाः १०. ८, ३.

अश्वऽबुध्यं १. ९२, ८.

अश्वऽबुध्यान् १. ९२, ७; १२१, १४.

अश्वे १. २५, ३; २७, १; ११६, ६; ११७, ४; ९; ११८, ९; १६१, ७; १६२, ४; १३; १५; १६३, २; ३. ५३, ११; २४; ४. १०, १; ३७, ८; ३९, ५; ५७, १; ६. ४६, २; ७. ७, १; ७७, ३; ८. ४, २१; १४, ३; १७, १५; ७४, १०; ७८, २; ९७, २; १०३, ७; ९. ९, ९; ६१, ३; ६२, ६; ६४, १०; ८७, १; ८९, ४; ९४, ५; १०८, ७; १०. १८, १४; ३९, १०; ६५, ११; ६८, ११; ९७, ४; १०७, ७; १०; ११९, १; १४३, १; २; १८८, १.

अश्वऽमघा ७. ७१, १.

अश्वंऽइव १०. १४९, १.

अश्वऽइष्टये ८. ६१, ७.

अश्वऽइष्टे २. ६, २.

अश्वऽमेधस्य ५. २७, ५.

अश्वऽमेधाय ५. २७, ४.

अश्वऽमेधे ५. २७, ६.

अश्वऽयते ६. ४५, २६.

अश्वऽयंतः ४. १७, १६; ७. ३२, २३; १०. १६०, ५.

अश्वऽया ८. ४६, १०; ९. ६४, ४.

अश्वयाऽइव ९. १०७, ८.

अश्वऽयुः १. ५१, १४; ४. ३१, १४; ८. ५३, ८; ७८, ९; ९. ३६, ६.

अश्वऽयुजः ५. ५४, २.

अश्वऽयूपाय १. १६२, ६.

अश्वयोः ६. ४७, ९.

अश्वऽयोगाः १. १८६, ७.

अश्वऽराधसः ५. १०, ४; १०. २१, २.

अश्वऽवत् १. ४८, १२; २. ४१, ७; ५. ५७, ७; ७. २७, ५; ७५, ८; ७७, ५; ९४, ९; ८. २२, १७; ४६, ५; ७२, ६; ९३, ३; ९. ४१, ४; ४२, ६; ६३, १८; ६९, ८; १०५, ४.

अश्वऽवतः १. १२२, ८; ७. १००, २.

अश्वऽवता ७. ७२, १.

अश्वऽवति १. ८३, १; ९२, १४.

अश्वऽवतीः १. ४८, २; १२३, १२; ७. ४१, ७; ८. ५, १०.

अश्वऽवतीं १०. ९७, ७.

अश्वऽवते १०. ४०, ५.

अश्वऽवत्या १. ३०, १७; ५३, ५.

अश्वऽवंतः ८. ४५, ११.

अश्वऽवंतं १. ८३, ४; ४. ४९, ४; ८. २, २४; १०. ४७, ५.

अश्वऽवित् ९. ५५, ३; ६१, ३.

अश्वऽसाः ९. २, १०; ६१, २०.

अश्वऽसातमः १. १७५, ५.

अश्वऽसां ६. ५३, १०.

अश्वऽसूनृते ५. ७९, १.

अश्वस्य १. ५३, २; ८४, १४; ११६, ७; १२; ११७, ६; १२१, २; १६२, ९; १८; १९; १६४, ३४; ३५; २. ३५, ६; ४. ३९, ३; ६; ५. ८३, ६; ८. ३२, ५; ५२, ५; ६१, ६.

अश्वस्यऽइव १०. ३४, ३.

अश्वऽहयः १०. २६, ५.

अश्वऽहयैः ९. ९६, २.

अश्वा १. १७४, ५; ३. ३५, ३; ४. ३३, १०; ३४, ९; ६. ५९, ३; ६७, ४; १०. २२, ४; ५; ७५, ७.

अश्वाऽइव ४. ५२, २; ७. १०४, ६.

अश्वाः १. ११५, ३; ११८, ५; १६३, १०; १६४, ३; १८०, १; ३. १, ४; ६, ८; ९; ७, २; ६१, २; ५. ५४, १०; ६१, २; ६. ६, ४; २४, ६; २७, ३; ७५, ७; ७. १८, १; ४१, ६; ६७, ४; ७५, ६; ९७, ६;

९. ७८, २; **१०.** ६, ६; ४४, ७; ९०, १०; ९५, ८; १०७, ११.

अश्वाःऽइव **५.** ५३, ७; ५९, ५; **८.** २३, ११; **१०.** ९७, ३; ११९, ३.

अश्वाजनीऽइव **५.** ६२, ७.

अश्वात् **१.** १६१, ७; **३.** ५३, २३; **१०.** ७३, १०.

अश्वान् **१.** ९२, १५; १०३, ५; १०४, १; १२६, २; १७१, १; **२.** ३४, ३; ८; **४.** ४३, ६; ४५, ६; **५.** ३१, १०; ५५, ६; ५८, ७; ५९, १; ६२, १; ८३, ३; **६.** ४७, २३; ५९, ५; ७५, १३; **७.** ३४, ४; **८.** १, ३१; ४१, ६; ६८, १७; ७५, १; **९.** ९७, ५०; **१०.** ३४, ११; ७९, ७; १०१, ७; १४९, ४.

अश्वानां **१.** १०१, ४; **५.** १८, ५; **६.** ६३, १०; **७.** १०४, १०; **८.** ३६, ५; ४६, २९; ५६, ४.

अश्वापयः **७.** १९, ४.

अश्वाऽइव **२.** ३४, ६.

अश्वाय **१.** १६२, १६; **५.** ३१, ४; **८.** ३०, ४; ९२, २५.

अश्वासः **१.** ३८, १२; १४८, ३; १८१, २; **२.** ११, ७; **४.** १४, ४; ४५, २; **५.** ५९, ७; ७५, ६; **६.** १६, ४३; २९, २; ६३, ७; **७.** ७४, ४; ७८, ४; **८.** १, ९; ५५, ४; **१०.** ७८, ५; ९१, १४; ९५, ९.

अश्वितन् **१०.** ७८, ७.

अश्विनः **८.** २२, ९.

अश्विनं **४.** ३७, ५; **५.** ४, ११; **८.** ६, ९; **९.** ४, १०; ६२, १२; ६३, १२; ६७, ६; ९३, ४; **९.** २५, ५; ७५, ९; १५६, ३.

अश्विना **१.** ३, १; २; १५, ११; २२, ३; ४; ४७, ३; ९२, १६; **३.** ५८, ७–९; **५.** ७४, १०; ७५, ३; ७८, २; ३; **८.** ८, १; ५; १६; १८; १९; २२, ६; २६, १९; २७, ८; ३५, १९; ८३, ७; ८५, १; ९; ८७, ६.

अश्विनां **१.** २२, २; ४४, ८; ५३, ४; ८९, ३; ११२, ४; १५६, ४; १५७, १; १६१, ६; १८१, २; **३.** २०, १; ५; ५८, ४; **४.** २, ४; ३४, ९; ४५, ५; **५.** २६, ९; ४३, ८; ४६, ४; ५१, ११; ७६, २; ३; ७७, १; २; **६.** ६२, १; **७.** ९, ५; ३५, ४; ४१, १; ४४, १; २; ५१, ३; ७३, १; ७४, ५; **८.** ५, ४; ८, ८; ९, १७; १९; १०, ३; १८, ८; २०; २२, ३; ११; १३; १५; २५, १४; २६, १०; १३; ७३, ६; १७; ९४, ४; **९.** ७, ७; ८, २; ८१, ४; **१०.** ३५, ६; ११; ४०, २; १४; ६४, ३; ६६, ५; ७३, ३; ४; ८५, ८; ९; २६; ९३, ६; ७; १२५, १; १२८, ७; १३१, ५; १८४, ३.

अश्विना **१.** ३०, १८; ३४, १–८; ११; १२; ४६, १; ६; ७; १५; ४७, १; २; ४–६; १०; ८९, ४; ९२, १७; १०९, ४; ११२, १–२५; ११६, ३; ६; ८; १८; २१; ११७, १; २; ४; ५; ८–१३; १५; १६; १८–२५; ११८, १–४; ८–११; ११९, २; ३; ५; १०; १२०, १; ६; १३९, ३; १५७, २; ४; १८०, ४; १०; १८१, ५; ७; ९; १८२, २; ४; **२.** ३९, ७; ८; ४१, ७; ९; **३.** ५८, ३; ५; **४.** १३, १; १५, ९; १०; ४३, ४; ४४, १–३; ६; ४५, ३; ७; **५.** ४१, ३; ४९, १; ७३, १; ७; ९; ७४, १; ८; ७५, २; ५; ६; ८; ७६, १; ४; ७७, ३; ७८, ४–६; **७.** ६७, ३–६; ६८, १; ३; ६–८; ६९, २; ५; ७; ७०, १; ३; ५; ७; ७१, २; ३; ७२, ५; ७४, १; ३; ४; **८.** ५, २; ७; १०; १४; १६–१९; २५; २७; २८; ३१; ३२; ३७; ८, २; ३; ६; ९–११; १३; २१; २२; ९, १–५; ८–१०; १२; १४; २१; १०, १; २२, १; ५; ९; १०; १७; २६, ४; ५; ७; १४; १६; ३५, १; ४; ७; १०; १३; १६; ४२, ४; ५; ५७, २; ३; ७३, १–३; ७; १२; १३; ८५, २; ३; ६; ८; ८७, १; २; **१०.** २६, ६; ३९, १; २; ६; ९–१३; ४०, ५; ६; ७; ८; ११; १२; ४१, २; ३; ५२, २; ६१, ४; ६५, १२; ८५, १४; ९२, १३; १३१, ४; १४३, ४.

अश्विनीं **५.** ४६, ८.

अश्विनोः **१.** ४६, १२; १२०, १०; १५७, ३; **३.** २९, ६; ५४, १६; **४.** ५२, २; ३; **५.** ४२, १८; **६.** ४९, ५; **७.** ७२, ३; **८.** ८, २३; ९, ७; १३; १६; १८; **१०.** १०६, ११.

अश्विनौ **५.** ७५, ७.

अश्विनौ **१.** २२, १; १८६, १०; **२.** ३१, ४; **३.** ५८, १; **४.** २५, ३; **८.** ८, १२; ९, १३; १०, २; **१०.** १७, २; १३२, १; १८४, २.

अश्विनौ **१.** ३०, १७; ११६, ५; १३; २५; ११७, ७; १७; ११८, ७; १५७, ५; १८०, ७; ८; १८२, ७; १८३, ६; १८४, ५; ६; **५.** ७५, १; **७.** ४०, ५; ६७, १०; ७२, ४; ७३, २; **८.** १०, ५; **१०.** ३९, १४.

अश्विऽभिः **६.** ४५, २१.

अश्विऽभ्यां **१.** ४४, २; १४; १६४, २७; १८२, ६; **५.** ५१, ८; ७३, १०.

अश्विया **४.** १७, ११.

अश्वी **४.** २, ५; **७.** १, १२; **८.** ४, ९.

अश्वीऽइव **२.** २७, १६.

अश्वे **१.** ३०, २१.

अश्वे इवेत्यश्वेऽइव **३.** ३३, १.

अश्वेन **१.** १६२, ३.

अश्वेभिः **७.** ५४, २; ९०, ६; **८.** ५, ७; १३, ११; ४६, २६; ८७, ५; **१०.** १०८, ७.

अश्वेषु **१.** २९, १–७; ११४, ८.

अश्वैः **१.** १६, ९; ८८, २; ११३, १४; ११७, १४; १७५, ४; **२.** १५, ४; **३.** ३०, १२; २०; ५८,

२; ४. ५१, ५; ५. २९, ९; ५५, १; ५८, ६; ६. ३९, ४; ६२, ३; ६५, २; ७. १८, २; ४१, ३; ४५, १; ६९, १; ७१, ३; ८. ५, ३५; ७, २७; ९. ९६, ११; १०. ३, ७; ७, २; ११, ७; ६८, १२; ७०, २; ३.

अश्वैत् १. ९२, १२; ११३, १५; १२४, ११; ७. ७७, २.

अश्व्यः १. ३२, १२; ७४, ७; ८. ६६, ३.

अश्व्यः ८. ४६, २१.

अश्व्यं १. ११७, २२; ११९, ९; ४. २८, ५; ५. ५२, १७; ६१, ५; ७. ९२, ३; ८. २१, १०; ३४, १६; ९. ७२, ९; १०८, ६; १०. ४८, ४; ९३, १२.

अश्व्यं १. ११२, १०; ८. ४६, ३३.

अश्व्यस्य ४. ४१, १०; ८. ४६, २२.

अश्व्यस्य ८. २४, १४.

अश्व्या ५. ७९, ७; ७. १६, १०; ६७, ९; ८. २७, ६; ३४, १४.

अश्व्यानां ८. २५, २३.

अश्व्यानि ६. ४४, १२; ७. १८, १९.

अश्व्ये ८. १३, २२.

अश्व्येन १०. ८७, १६.

अश्व्यैः ६. ६०, १४; ८. ७३, १४.

अषंऽतरा १. १७३, ४.

अषाळ्हः ३. १५, ४; ७. २०, ३; २८, २; ९. ९०, ३.

अषाळ्हं १. ५५, ८; ९१, २१; ६. १८, १; ८. ७०, ४; १०. ४८, ११.

अषाळ्हाय २. २१, २; ७. ४६, १; ८. ३२, २७.

अषाळ्हेन ६. १९, २.

अष्ट ८. २, ४१; १०. २७, १५.

अष्ट ७. ८४, ५; ८. ७०, ५; १०. १२६, १.

अष्टऽकर्ण्यः १०. ६२, ७.

अष्टमं २. ५, २; १०. ११४, ९.

अष्टवे ४. ३०, १९.

अष्टा १. १२१, ८.

अष्टाऽपदी १. १६४, ४१.

अष्टाऽपदीभिः २. ७, ५.

अष्टाऽपदीं ८. ७६, १२.

अष्टाभिः २. १८, ४.

अष्टाऽवंधुरं १०. ५३, ७.

अष्टौ १. ३५, ८; १२६, ५; १०. ७२, ८.

अष्ट्रा ६. ५३, ९.

अष्ट्रां ४. ५७, ४; ६. ५८, २.

अष्टाऽवी १०. १०२, ८.

अष्ठीवत्ऽभ्यां १०. १६३, ४.

अष्ठीवंतौ ७. ५०, २.

असः ६. ३६, ५; ७. २४, १; ८. १००, २; १०. ४४, ४; ५०, ५; ८५, २६; ३६; १२४, १.

असक्त १. ३३, ३.

असंक्रां ६. ६३, ८.

असक्षत ८. ६४, ९.

असंघ्नोः १. ३१, ३.

असचत्ऽद्विषः ८. २०, २४.

असचंत ३. ३१, ४.

असजत १०. १२४, ७.

असज़ात्या १०. ३९, ६.

असत् १. ९, ५; ८९, ५; १०७, १; ११४, १; १४३, ६; १७३, ९; १७६, ५; १८६, ३; २. २३, १४; ३. २३, ३; ५१, ११; ४. १६, २०; ६. २३, ५; १०; २४, ५; ३४, ५; ७. २०, ८; ५३, ३; ८५, ४; १०४, १२^{२}; १३; ८. ३१, १८; ९. ८९, ६; १०. ५, ७; २७, १; २९, २; ३७, १०; १०१, ३; १२९, १; १३७, ५; १४१, ४.

असत् १. ५७, २; १२५, २; १२९, ८; १५६, २; १६४, १६; १७३, १०; २. २६, १; ४. २, १०; ४, ७; ८. २०, १७; २८, ४; ३१, ३; ६१, ४; ८९, ४; १०. १०, ११; ८९, १४.

असतः ५. १२, ४; ७. १०४, ८; १०. ७२, २.

असता ४. ५, १४.

असति १. १२४, ११; ६. २३, ९; ४५, १४; ८. २०, १५; १०. ८५, २५; १२९, ४; १९१, ४.

असति ५. ५३, १५.

असत्याः ४. ५, ५.

असथ ५. ६१, ४; १०. १०३, १३.

असथ ८. ३०, २; १०. ९७, ५.

असंथः ६. ६३, १.

असंदः ७. ११, २.

असदः ५. २१, ४^{२}; ९. १७, ८; ६२, ७; १०. ९१, ४.

असदत् १०. १७९, १.

असदत् २. ९, १; ३. ६२, १५; ६. ५७, २; ९. १, २; १६, ४; १९, ३; ६२, ४; ३०; ७२, ५; ८९, १; ९७, ३७; ४५; १०७, ५.

असदन् ८. २८, १; १०. ४३, ४.

असदन् १. १९१, ४; १०. ३०, १५.

असन् १. ८९, १; ५. ३३, ३; ७. ८, ५; १०४, ८; ८. ४५, ३३; १०. २९, ४; ५३, ८.

असन् १. ३८, १५; ४. ३, ११.

असनत् १०. ६७, १०.

असनत् ५. ३०, १४.

असनन् ८. २८, १.

असनं १. १२०, १०; ८. २५, २४; ४६, २२; २९.

असना १०. ९५, ३.

असनां १. १४८, ४; १५५, २.

असनाम ८. ४७, १८; १०. ६२, ११.

असनाम ८. २५, २२.

असनाय १. १३०, ४.

असने १. ११२, २१.

असनोः ८. ४९, १०.

असनोत् ३. ३४, १०^{२}.

असन्वन् ७. १८, १.

असपत्नः १०. १७४, ४; ५.

असपत्ना १०. १५९, ४; ५.

असपंत ७. ८३, ८.

असपर्यन् ३. ९, ९.

असमः ६. ३६, ४; ८. ६२, २.

असमनाः १. १४०, ४; ७. ५, ३.

असमने ६. ४६, १३.

असमं १. ५४, ८; १०. ४७, ८; ८९, ३.

असमष्टऽकाव्यः २. २१, ४; ९. ७६, ४.

असंमा १. ५४, ८; ६. ६७, १.

असंमाः २. १३, ७; १०. ७१, ७.

असंमातिऽओजाः ६. २९, ६.

असंमातिं १०. ६०, २.

असंमातिपु १०. ६०, ५.

असंमानि ७. ४३, १.

असंऽदितः ४. ४, २.

असंऽदिनं ८. १०२, १४.

असंऽमृष्टः ५. ११, ३.

असंऽयत्तः १. ८३, ३.

असंरः १०. १०८, ३.

असरः ९. ११०, ४.

असंरत् ९. ८७, ६.

असरत् २. २४, १४; ४. ३८, ९; ९. ३, ८; ३७, ५; ६२, १६; ८६, ४४; ९२, २; ९७, ४५.

असरन् ९. ६, ४; ८२, ३.

असंरं १०. १०८, ४.

असंर्जि १. ३८, ८; १८१, ७; १९०, २; ९. ३६, १; ६७, १५; ८६, ४६; ९१, १; ९७, ४६; १०६, १२; १०९, १९.

असर्जि ४. २६, ५; ६. ६३, ७.

असश्चतः १. १३, ६; ११२, २; १४२, ६; २. २५, ४; ९. ५७, १; ६२, २८; ७३, ४; ७४, ६; ८५, १०; ८६, २७.

असंश्चतं १. ११२, ९.

असश्चतं २. ३२, ३.

असश्चता १. १६०, २; ७. ६७, ९.

असश्चताऽइव १०. ६९, ८.

असंश्चंती ३. ५७, ६; ८. ३१, ४.

असंश्चंती इति ६. ७०, २.

असंश्चुषी ९. ८६, १८.

असंसंतः १. १४३, ३.

असंसि २. २६, २; ४. ५७, ६^{२}; १०. १७४, ३.

असंसृग्रं १०. ३१, ३.

असस्रग्रं ९. ९७, ३०.

असंस्तन १. १६१, ११.

असंहंत ३. २९, ९.

असंहिष्ट ७. ९८, ५.

असाक्षि १०. १५९, १.

असादयत् ८. २३, १७; ५१, २.

असादयंत ३. ९, ९; १०. ७, ५.

असांदि ७. ७, ५.

असादि १. ६०, २; ३. ४, ४; ४. ६, २; ५. ४३, ७.

असानिषं ६. ४७, २३.

असांम १. ५३, ११; १७३, ९; ४. २, १०; १०. ५३, ४.

असांमि १. २५, १५; ३९, ९; १०^{२}; ६. १९, २; ३८, ५; १०. २२, ३; ७४, ३; ९६, ५.

असांमिऽभिः १. ३९, ९.

असांमिऽशवसः ५. ५२, ५.

असारयंत १०. ५६, ५.

असांवि १. ८४, १; ५. ४३, ५; ७. २१, १; ९. ६२, ४; ७७, ५; ८२, १; १०. १०४, १.

असाविषुः ९. २१, ७.

असावीत् १. १२४, १; १५७, १; ५. ८१, २.

असिं १. १, ४; १२, ३; १३, ४; १५, ३; ४४, २; ९; १०^{२}; ५९, ३; ७४, ४; ८१, २^{३}; ८७, ४; ९४, ७; ९७, ६; १२९, २; १४४, ७; १६३, ३^{४}; १८९, ६; २. १, २; ९, ४; २३, ११; ३२, ६; ३. ३, ७; ९, ३; ५३, १८; ४. ६, १; ३२, १३; २१; ४६, १; ५. ९, ४; २८, ५; ३५, ४; ६. २, ७; ४, ४; १३, २; ४०, ५; ४८, ८; १९; ७१, २; ७. ३२, २४; ८. ४, १; ६, ४१; ११, ८; १२, १८; १३, १५; १४, ११; २३, २९; २४, २; ३९, ३; ४३, २८; ४४, २४; २९; ६१, १४; ९०, २; ९२, २८; ९३, ३३; ९५, ३; ९७, ५; ९८, ५; ६; ९. ६५, ४; ८५, २; ९७, ५५^{३}; १०. १, ४; २४, ३; ३५, ७; ९८, १.

असि १. १५, १२; २७, ६; ३१, १०; १२; १६; ३६, ५; ९; १२; ५०, ४; ५३, २; ५९, १; ५; ६२, १२; ७५, ३; ४; ९१, ३^{२}; ५^{२}; ९४, ५; ६; १३^{२}; १०२, ८; १३२, ३; १६९, १; १८८, ३; २. १, ३; ५; ७; १०–१२; १५; ७, ५; १२, १५; १३, २–१२; २०, २; २३, २; ४; २७, १०; ३३, ३; ४१, २; ३. ३, १०; ९, ३; २५, १; २८, ३; ३०, ३१; ३४, २; ४५, ५; ४६, २; ४७, १; ४. ४, १; ९, १; २०, ८^{२}; ३०, २; ७; २२; ३२, २; १९; ५२, ३^{२}; ५. १, ८; १३, ४; ६; २८, ४; २९, १; ४०, ७; ४४, २; ६. २५, ५; ४४, १२; २१; ४५, ५; २६; ४७, २६; ३०; ४८, ९; ५५, ३; ५६, ५; ५८, १; ७. ११, १; १९, १; २२, ७; २९, ४; ३१, ६; ७; ३२, १७; ३३, ११; ३७, ५; ९८, ६; ८. १, ६; ७; २, ९; ४, १; ११, १; २; १३, १५; २६; १९, ३१; २१, १३; २३, ३०; ३३, १०; ३६, १; ५; ५१, ७; ६०, ३; ५; ६; १९; ६१, ६; ६४, २; ६९, १२; ७१, २; ७९, ३; ८०, ३; ७; ८८, ४; ८९, ६; ९०, २; ५; ९५, ४; ९७, ९; ९८, २^{२}; ९९, ५^{२}; १०१, ११^{३}; १२^{२}; ९. २, १०; १८, १; ४७, ५; ५९, ४; ६१, २०; ६४, १; २; ६६, ३; १६; ६७, १३; ८६, २८; २९; ३८; ३९; ८८, ३; ४^{२}; १०४, ५; १०९, ६; १०. १, २; २, १; २; ४, १; २; १०, १३; ११, ५; ५४, ५; ५६, ३; ६१, २४; ७९, ५; ८४, ४; ९१, ३^{२}; ९७, १८; २३; १००, ५; १०२, १२; १०४, ६; ११०, १; ३; १३३, ३; ४; १४१, १; १४५, ५; १५२, १; १५३, २; ३; ५; १५६, ५; १८०, १; १८६, २.

असिः १०. ७९, ६; ८९, ८.

असिंक्नीः ७. ५, ३.

असिंक्नीं ९. ७३, ५; १०. ३, १.

असिक्न्या १०. ७५, ५.

असिंक्न्यां ४. १७, १५; ८. २०, २५.

असिचन् १०. २९, ७.

असिंचन् ३. ४८, २.

असिंचतं १. ११६, ७; ११७, ६.
असिंचन् १. ८५, ११.
असितः १. ४६, १०.
असितं ४. १३, ४; ५१, ९.
असिना १. १६२, २०.
असिन्वती इति १०. ७९, १.
असिन्वन् २. १३, ४; ७. ३९, ६; ८. ४५, ३८; १०. ७९, २.
असिन्वं ५. ३२, ८.
असिन्वा १०. ८९, १२.
असिं १०. ८६, १८.
असिरेण ९. ७६, ४.
असिष्यन् ६. ३, ५.
असिसासः ८. ५०, १०.
असिसासत् ८. ५१, २.
असिसासन् ३. ३१, ९.
असिस्यदत् ९. ८१, २.
असिस्यदत् ९. १४, १; २७, ६; ३०, ४; ४९, ५; ६०, ३; ७८, १; १०६, १२.
असिस्यदंत ९. ६८, १.
असीदः ६. १, २.
असीदत् १. १४३, १; १०. ८१, १.
असीदत् ५. १, ६; ८. ४२, १.
असीदतं १०. १३२, ७.
असीदं १०. ५२, २.
असुः १. ११३, १६; १६४, ४; १०. १२१, ७.
असुः १. १७९, २.
असुतः ७. २६, १.
असुतात् ६. ४१, ४.
असुतानां ८. ६४, ३.
असुऽतृपः १०. ८२, ७; ८७, १४.
असुऽतृपौ १०. १४, १२.
असुऽनीतिं १०. १२, ४; १५, १४; १६, २.
असुऽनीते १०. ५९, ५; ६.
असुन्वतः १. १०१, ४; ५. ३४, ६; ८. ६२, १२.
असुन्वता ४. २५, ७; ५. ३४, ५; १०. ४२, ४.
असुन्वतां १. ११०, ७.
असुन्वंतं १. १७६, ४.
असुन्वां ८. १४, १५.
असुं १. १४०, ८; १८२, ३; २. २२, ४; १०. १२, १; १४, १२; १५, १; ५९, ७.
असुर १. २४, १४; १७४, १; २. २७, १०; २८, ७; ४. २, ५; ८. ९०, ६; १०. ९६, ११; ९९, १२; १३२, ४.
असुरः १. ३५, ७; १०; ५४, ३; १३१, १; २. १, ६; ३. ३, ४; ५. १५, १; २७, १; ४२, १; ५१, ११; ८३, ६; ७. ३०, ३; ५६, २४; ८. ४२, १; ९. ७३, १; ७४, ७; १०. ११, ६; ७४, २.
असुरःऽइव ८. १९, २३.
असुरऽघ्नः ६. २२, ४.
असुरऽघ्ने ७. १३, १.
असुरऽत्वं ३. ५५, १; १०. ५५, ४.
असुरऽत्वा १०. ९९, २.
असुरं ५. ४२, ११; ७. २, ३; १०. ५६, ६.
असुरस्य १. ११०, ३; १२२, १; १२६, २; २. ३०, ४; ३. २९, १४; ३८, ४; ५३, ७; ५६, ८; ४. ५३, १; ५. ४९, २; ६३, ३; ७; ७. ६, १; ९९, ५; ८. २०, १७; १०. १०, २; ३१, ६; ९२, ६; १३८, ३; १७७, १.
असुरऽहा १०. १७०, २.
असुरा ७. ६५, २; ८. २५, ४.
असुरा १. १५१, ४; ७. ३६, २.
असुराः १. ६४, २; ८. ९६, ९; १०. १२४, ५.
असुराः ८. २७, २०.
असुरान् १०. ५३, ४; १५७, ४.
असुराय ५. १२, १; ४१, ३; ९. ९९, १; १०. १२४, ३.
असुरे १०. ९३, १४.
असुरेभ्यः ८. ९७, १.
असुरेषु १०. १५१, ३.
असुरैः १. १०८, ६; १०. ८२, ५.
असुर्य २. २३, २; १०. १०५, ११.
असुर्यैः ८. १०१, १२.
असुर्यं २. २७, ४; ३३, ९; ३. ३८, ७; ५. १०, २; ६६, २; ६. २०, २; ३०, २; ३६, १; ७४, १; ७. ५, ६; ६५, १; ९. ७१, २.
असुर्यस्य २. ३५, २; ७. २२, ५.
असुर्या १. १६७, ५; ७. ९६, १.
असुर्याऽइव १. १६८, ७.
असुर्याणि ४. ४२, २; १०. ५४, ४.
असुर्यात् १. १३४, ५.
असुर्याय ४. १६, २; ७. २१, ७; ६६, २; ८. २५, ३; १०. ५०, ३.
असुवत् १. ११०, ३.
असुस्वीन् ४. २४, ५; ६. ४४, ११.
असुस्वेः ४. २५, ६.
असूत १. १६८, ९; ३. ३८, ५; ५. २, २.
असूत ३. ३९, ३; ५. ७, ८.
असूदयत् ३. ३१, ७.
असूदयंत १. ७२, ३.
असूयन् १०. १३५, २.
असूरे ८. १०, ४.
असूर्तं १०. ८२, ४.
असूर्ये ५. ३२, ६.
असृक् १. १६४, ४.
असृक्षत ८. ६३, ७; ९. ६४, ४; ८२, २; १०. ८६, १.
असृक्षत १. १३५, ६; ५. ५२, ६; ८. ५२, ९; ९३, २३; ९. १६, ५; ४६, २; ६२, २२; ६३, २५; २७; ६४, ७; १६, ६६, १०; २५; ६७, १८; ८६, ४; १०६, १४; १०७, २५.
असृक्षि ८. २७, ११.
असृक्षि २. ३५, १.
असृग्रन् ९. ४६, १; ६७, १७.
असृग्रन् ९. ८६, ४; ८७, ५; ८८, ६; ९६, २२; ९७, २९; ३१.
असृग्रं १. ९, ४; ९. ७, १; १३, ६; ६२, ७; ६६, ११.
असृग्रं ९. १२, १; १७, १; २३, १; ६२, १; ६३, ४; २६.
असृजः ३. ३२, ६; ५. ३२, १; ८. ३, १०.
असृजः १. ३२, १२; ५७, ६; १३०, ५;

६. १७, ६; १२; ३०, ४; **८.** ९६, १८; **१०.** १३३, २; १३८, २.

असृंजत् **१०.** ५४, ६.

असृजत् **१.** ३३, १३; ५१, ११; ८०, १०; **२.** १५, ३; ४; २८, ४; **३.** १, ९; ३१, ११; १६; **४.** १८, ७; १९, ८; **५.** २९, २; ३०, १०; **६.** ३२, २; **१०.** ८०, ३; ९८, ५.

असृजत **१.** ११०, ८; **१०.** ६७, ८.

असृजन् **१०.** ६६, ८.

असृजंत **४.** १९, २; **८.** ५९, ६.

असृष्ट **१०.** ३१, ९.

असेधः **५.** ३१, ७.

असेधत् **६.** ४७, २१.

असेन्या **१०.** १०८, ६.

असौ **१.** १०५, १६; १९१, ९; **५.** १७, ३; **८.** ९१, २; ६; **१०.** १३२, ४; १४६, १; १५९, १.

अस्कंभायत् **१.** १५४, १.

अस्कभने **१०.** १४९, १.

अस्कंधोयु **६.** ६७, ११; **७.** ५३, ३.

अस्कंधोयुः **६.** २२, ३.

अस्तः **१०.** १११, ६.

अस्तंऽस्तातिं **५.** ७, ६.

अस्तभायुः **१.** ६२, ५.

अस्तभायत् **१.** १६४, २५; **२.** १५, २; **६.** ४४, २२.

अस्तभ्नाः **२.** १३, १०; **७.** ९९, २; ३; **८.** ८९, ५; **१०.** ५५, १; १५३, ३.

अस्तंभ्नात् **२.** १२, २; १७, ५; **३.** ३०, ९; ५३, ९; **८.** ४२, १; **१०.** ११३, ४.

अस्तभ्नात् **६.** ८, ३; ४७, ५.

अस्तं **१.** ६६, ५; ११६, ५; १३०, १; **३.** ५३, ४; ६; **४.** १६, १०; ३४, ५; **५.** ६, १[२]; ३०, १३; **६.** ४९, १२; **७.** ३७, ४; ६; **८.** ३, २३; ९१, १; **९.** ६६, १२; ९७, ८; **१०.** १४, ८; २८, १; ३४, १०; ८५, ३३; ८६, २०; २१; ९५, २; ४; १३; १११, १०.

अस्तंऽइव **१.** ११६, २५.

अस्तंऽईके **१.** १२९, ९.

अस्तंभीत् **८.** ५१, ८.

अस्तंभीत् **३.** ५, १०.

अस्तरित्यस्तः **७.** १८, ११.

अस्तरित्यस्तः **२.** ११, २०.

अस्ता **१.** ६१, ७; ७१, ५; **२.** ४२, २; **४.** ४, १; २७, ३; ३६, ६; **१०.** ८७, ६; १०३, ३; १३३, ३.

अस्ताऽइव **१.** ७०, ६; **४.** ३१, १३; **६.** ३, ५; २०, ९; ६४, ३; **१०.** ४२, १.

अस्तारः **१.** ६४, १०.

अस्तारं **८.** ९३, १.

अस्तारि **६.** ६३, ३.

अस्तावि **१.** १४१, १३; **८.** ५२, ९; **१०.** ४५, १२; ६३, १७.

अस्तावि **६.** २३, १०.

अस्तिं **१.** २२, ४; ३३, २; ३६, १२; ३७, १५; १००, २; १०८, २; १४९, २; १६२, ९; १०; १६७, ७; १७०, १; १७३, ६; १२; १७८, १; १९०, ३; **२.** २७, ६; ३३, ७; **३.** २९, १[२]; ३६, ९; **४.** १८, ४; २०, ७; २१, २; ४५, ७; ५८, १; **५.** ७, ९; ३१, २; ३९, १; ३; ४२, २; ४; ६५, ४; ७०, १; ७४, ६; **६.** १८, ३; ६; १५; २५, १; २९, १; ३४, २; ४४, १; ६२, ८; ६५, ४; ७४, ३; **७.** २०, ५; २२, २; २७, २; ३; ३२, १९; ५६, १८; २१; ६८, ५; ७१, ४; ८६, ६; ९७, ४; **८.** १, २७; ३१; ९, १५; १०, ३; १८, १९; २०, २२; २३, १०; २४, ९; १९; २१; २७, १०[२]; ३०, १; ३३, ६; ४६, ९; ४७, १३; ५४, ५; ६६, १३; ६७, ३; ६; ७[२]; ७०, ८; ८१, ८; ९४, ४; १००, ३; १०२, १९; **१०.** १२, ५; ८२, ५; १३१, ३; १४२, १[२].

अस्ति **१.** २७, ८; ४०, ८; ४१, ४; ६२, ६; ८४, १९; १०५, १३; १०९, १; १६४, १; १६५, ९; **२.** १२, ५; २४, ७; ३३, १०; **४.** ३०, १; **५.** ३, ५; २९, १४; ७७, २; **६.** १८, ३; १२; २१, १०; २४, ५; २५, ५; ३०, ४; ६६, ८; **७.** ३, २; ४, ७; २९, ३; ४०, ३; ६०, ७; **८.** १४, ४; ३२, १६; ६६, ९; ६७, १९; ७४, १५; ७८, ७; १००, ३; **१०.** २७, २१; ३१, ८; ७१, ६; ११७, ४.

अस्तुं **१.** १३९, १.

अस्तु **१.** ७, १०; ८, ५; १३, १०; ११; १६, ७; २४, ९; २६, ७; २७, ९[२]; ३०, ५; १२; ३९, २; ४; ५५, ७; ८२, ५; ८६, ७; ९०, ७; ८; ९१, १९; ९४, ८; ९८, ३; १००, १९; १०२, ११; १०८, २; ११४, १०; १२५, ७; १४०, ११; १४७, ४; १६२, ८; ९; ११; १४; १६५, १०; १७२, १; १८४, ४; १८५, ११; **२.** ४, २; १४, ११; २०, ३; २८, १; **३.** ३०, ६; १८; ४४, १; ५४, ३; १८; २१; ५९, २; **४.** १, १८; २, ७; ४, ७; १२, १; १५, ९; २१, १; २६, ४; ३७, ६; ४६, ७; ५७, ३; **५.** ११, ५; ३४, ९; ४७, ७[२]; ५३, ९; ७४, ९; **६.** १६, २६; १८, ५; २३, ३; २६, ८; २९, ६; ३७, ५; ४८, १८; २०; ५८, १; ६६, १; ७; ६७, ८; **७.** १, १४; ४, २; २०, १०; २५, ३; ३४, १५; २२; ३५, २[२]; ३; ४; ५[२]; ६; ७; ९[२]; १०; ११; १३[२]; ३८, ३; ४०, ३; ४१, ५; ५६, ५; १७; २४; ५७, ४[२]; ५८, ४; ६६, ५; ६७, ६; ७०, ५; ८५, ४; ८६, ८[२]; १००, ३; १०१, ५; १०४, ३; ८; ११[२]; **८.** १, ३२; १७, ६[२]; १०; १९, ९; ६६, १५; ८३, ४; ९३, १८; ९६, ७; १००, २; १०२, २१; **९.** ६३, ३; ९२, ५; **१०.** ७, ४; १५, २; ३२, ९; ३४, १४; ३५, १३; ४२, ३; ४३, २; ४४, ९; ५१, ८; ९; ५९, ४; ६२, १; ७७, ७; ८०, २;

८१, ६; ८५, २३; ९७, २०; २३; १००, ४; ९; १०; १०२, ११; १०८, ६; १२८, १–४; १६५, १–४; १८०, १; १८५, १; १९१, ४.

अस्तुः १. ६६, ४; १४८, ४; १५५, २; ९. ७७, २.

अस्तुतः ५. ६१, ८; ६७, ५.

अस्तृंणन् ३. ९, ९.

अस्तृणन् १. १८८, ४.

अस्तृंणात् ८. ४१, ८; ६३, ७.

अस्तृंतः १. ४१, ६; ६. १६, २०; ८. ९३, ९; १५; ९. २७, ४.

अस्तृंतं १. ४, ४; १५, ५; १४०, ८; ८. १, ११; ६६, १०; ९. ९, ५; १०. ४८, ११.

अस्तृंतऽयज्वनः ८. ४३, १.

अस्तृंऽभिः १. ८, ४.

अस्त्रृंन् १०. ६४, ८.

अस्तें ७. १, २.

अस्तोंढ्वं १. १२४, १३.

अस्तोंभयत् १. ८८, ६.

अस्तोंषत १. ८२, २.

अस्तोषि १. १२२, १; ५. ४१, १०; ८. ३९, १; १०. ७७, १.

अस्तोष्ट १. ७७, ५.

अस्तौत् १०. ६७, ३; १०५, ६; ११[२].

अस्त्रां ८. ९६, २.

अस्थन्ऽवंतं १. १६४, ४.

अस्थऽभिः १. ८४, १३.

अस्था १०. ४८, १०.

अस्थांत् १. ३५, १०; ६५, ४; १४१, ७; २. ४, ७; ३०, ३; ३५, ९; ३. ३९, ३; ७. ३, २; ८. २७, १२.

अस्थात् १. ३५, ४; ७४, ८; १२३, १; १४९, ४; १६२, २१; १६४, १७; २. ३, १; ३८, १; ४; ३. ५, ३; ७; १४, १; ६१, ६; ४. ६, ४; १८, ५; ५१, १; ५. १, २; ८०, ५; ६. ४१, २; ४५, ३१; ६३, ४; ७१, ४; ७. १६, ३; ७०, १; ७७, २; ९२, २; ९. ८५, ९; १२; ८६, ८; ८७, ४; १०. १, १; ३, ३; १०३, ९.

अस्थापयध्वं १०. १०१, ११.

अस्थापयंत १. १६७, ६; १०. ५६, ६.

अस्थित २. ५, ६.

अस्थित १. ४०, ७; १०. ११९, ४; १२७, ७.

अस्थिरन् १. ९४, ११.

अस्थिरन् १. ८०, ८; १३५, १[२]; ८. १०२, १३; ९. ८३, २.

अस्थुंः ३. १, ७; ४. ५१, २; ६. ६४, १; ७. ८३, ३; ८. ९५, १.

अस्थुः १. ११५, ३; १२३, १; ६; १२६, ३; १९०, ६; ४. ३४, ३; ४१, ८; ९; ५. ७६, १; ६. ४४, २०; ७. २३, ३; ४३, २; ६०, ४; ६८, २; ७५, ३; ८. ४८, ११; ९. ५३, १; १०. १०७; २; ११४, १०; १२३, ४.

अस्थूरि ६. १५, १९.

अस्थेंयसांऽइव १०. १५९, ५.

अस्नाता १०. ४, ५.

अस्नातारां ४. ३०, १७.

अस्नातृन् २. १५, ५.

अस्पंदमानः ४. ३, १०.

अस्पर्रिर्त्यस्पः ५. १५, ५.

अस्पंष्ट १. १०, २.

अस्पार्षं १०. १६१, २.

अस्पृंतः ९. ३, ८.

अस्पृंतं ८. ८२, ९.

अस्पृध्रन् ६. ६६, ११; ७. ५६, ३.

अस्पृशत् ६. ८, २.

अस्पृहयं १०. १३५, २.

अस्फुरः ८. ३, १९.

अस्फुंरत् २. १२, १२.

अस्फुरत् २. ११, ९.

अस्मत् १. २४, ९; १५; ३३, ३; ६०, ३; ६३, ५; ९२, १६; ११४, ४; १२१, १५; १२९, ६; १०; १३४, २; १३९, ५; ८[२]; १४४, ३; १८९, १; ३; २. ६, ४; ३३, २; ११; ३. ८, २; ४१, ८; ५८, २; ४. १, ४; ४, ५; ११, ६; १२, ६; ४१, १; ५. २, ७; ३३, ३; ५६, ३; ५७, १; ७७, २; ६. ४४, १६; ७४, ३; ७. १, २१; २२, ६; ३२, १; ३४, १; ३८, ७; ४४, ३; ५६, ९; ७१, १; २; ८८, ७; १००, ६; ८. २, ६; २०; २६; ८, ८; ११, ३; १८, ११; १६; ४५, ३७; ४७, १३; ६१, १६; ६७, १५; ७४, ७; ७५, १३; ९. ८१, ३; १०४, ६; १०५, ६; १०. ५, १; २०, ८; ३७, ४; ४५, १, ५३, १; ५४, ३; ६३, १२; ९१, १२; ९९, ७; १३४, ५; १४४, ६; १६४, ३.

अस्मऽत्रा १. १३२, २; १३७, १; ३; ४. ३२, १८; ४१, १०; ८. १८, १४; ६३, ४; १०. ४४, ३.

अस्मत्रांचंः ६. ४४, १९.

अस्मत्ऽसंखा ६. ४७, २६.

अस्मद्र्यंक् ३. ५४, २२; ४. २२, ८; ५. ४, २; ६. १९, १; ३; ७. ७९, ५; ९. ९३, ४; १०. ११६, ६.

अस्मद्र्यंचः ७. १९, १०.

अस्मऽध्रुक् १. ३६, १६; १७६, ३; ८. ६०, ७.

अस्मभ्यं १. ७, ६; १०, ८; १७, ८; २४, १४; ३४, ३; ४८, ९; ६३, ८; ७९, ५; ८१, ६; ८५, १२; ९०, ३; ९२, १३; १०२, ४; १०८, १३; १११, ३; ११४, ५; ११७, २; १३२, ४; १४०, ११; १५९, ५; १७०, ३; १७६, ४; १८७, ११; १८९, ३; २. ११, १९; १३, १३; १४, १२; १८, ८; ३८, ११; ४०, ४; ३. ३०, २१[२]; ३६, ९; ५०, ३; ५४, ११; ५७, ६; ६२, १४; ४. १, ३[२]; २०, ७; २२, ९; १०[२]; ३१, १३; ३६, ८; ३७, ७; ५५, ८; ९; ५. १०, १; ३५, १; ३८, ४[२]; ४४, ६; ४७, ७; ५३, १३; ५५, ९; ६. १९, ६; ४४, १८; ४६, ८; ५१, ५; ५२, १५; ५३, ५; ७१, ६; ७५, ११; ७. ५०, ४; ६८, ३; ७४, ५; ७८, १; ७९, ४; ८१, ६; ९४, ७; १०४, १४; ८. ५, १२; ११, १०; २६, १५; ३०,

४; ४६, १९; ६७, १९; ८१, ९; ८३, १; ८४, ६; **९.** २, ९; ७, ९; २१, ५; ३३, ६; ४०, ३; ४३, ४; ४६, ५; ४९, ३; ६२, ३; ६३, ११; ६५, १३; २१; ८६, ४१; ९०, ४; ९१, ६; ९७, २१; १०१, १०; ११; १०४, ४; १०६, ६; **१०.** १४, १२; ३०, ११; ४७, १; ५६, २; ८४, ७; ११६, ९; १२६, ७; १३३, ७.

अस्मऽयु **१०.** ९३, १४.

अस्मऽयुः **१.** १३१, ७; १३५, २[२]; १४२, १०; **३.** ४१, ७; ४२, १; **५.** ७४, ८; **६.** ४८, २; **७.** १५, ८; **८.** १९, ७; ७०, १२[२]; **९.** २, ५; ६, १; १४, ८; ६४, १८; ७८, ५; **१०.** ९३, ११.

अस्मऽयुं **२.** २३, ८.

अस्मयू इत्यस्मऽयू **१.** १३५, ५; १५१, ७; **७.** ७४, ४; **८.** २६, १४.

अस्माक **१.** १७३, १०.

अस्माकं **१.** ७, १०; १३, १०; २५, १५; २७, २; ४; ३०, ११; ३३, १; ७९, ११; ९४, ८; १६; १०२, ४; ५; ११४, ३; १२९, १; ४[२]; १३२, ६; १३८, २; १३९, ९; १४०, १०; १२; १५२, ७[२]; १५७, २; १७४, १०; १८७, २; **२.** २, १०; ३०, ४; ३१, १; **३.** ३१, १४; ३९, ४; ६२, १५; **४.** १, १३; ९, ७[३]; २०, ३; २२, १०[२]; ३१, १४; १५; ३२, १; १५; **५.** ४, ८; ९; ३५, ७; ८; ४१, १६; ४४, ७; ६५, ६; ७४, ९; **६.** ८, ७; ४५, ३०; ४६, ४; ४७, ३१; ५४, ६; **७.** २८, १; ३२, ११; ५१, २; ५७, २; ५९, ३; ६९, ६; ८२, ९; **८.** १, ३; १५; ४, १८; ५, १८; ६, ४२; १२, १७; १७, ४; २६, २०; ३३, १५[२]; ४५, ९; ५२, ८; ५४, ८; ५७, २; ६४, ६; ६७, १९; ८८, ६; ९२, ३२; **१०.** २२, ७; २६, ४; ९; ३२, १; ३६, ६; ३७, ११; ८१, ६; ८४, ५; ९७, २०; २३; १०३, ४; ७; ११[३]; १०८, ५; ११२, ७; १३३, १; १३६, ३; १५१, ३; १५७, ३.

अस्माकासः **१.** ९७, ३; **५.** १०, ६; **६.** २५, ७; **७.** ७८, ५.

अस्माकेन **६.** ४५, १५; **१०.** ४२, १०.

अस्माकेभिः **१.** १००, ६; **२.** ३०, १०; **६.** १२, ४; **८.** १५, १२; ४०, ७.

अस्मात् **१.** १७१, ४; १८२, ८; **३.** ५३, १९; **१०.** ९८, १२.

अस्मात् **२.** २३, ५; **४.** १७, १०; **५.** ३२, ३; **८.** २७, १८; ९६, ६; **१०.** ११७, ४.

अस्मान् **१.** ९, ६; १७, ७; २४, १२; ३१, १८; ४७, ५; ८१, ३; ८४, २०; ९५, ९; ९८, ३; १०९, ७; ८; १११, ५; ११२, २५; १६५, १४; १७४, १; १८९, १; २; **२.** १, १६; २, १३; ११, १५; २८, १०; ३०, ५; ६; ८; ३९, ४; **३.** ८, १०; ३३, ६; ५३, २०; ६२, ३[२]; **४.** ४, १५; ९, ८; १२, ४; ३१, १०[३]; ११; १२[२]; **५.** ४, ६; ३३, ५; ५५, ४; १०; **६.** १९, ३; ४१, ५; ४४, ९; ४५, ३०; **७.** १, २२; १२, २; १५, ३; १८, २; १९, ९; २३, २; ३४, १२; ४८, २; ५४, १; ५५, ३; ९३, ६; १०४, २३; **८.** २, १९; ३, १; २; ८, २१; २२, ४; २५, २१; ३३, १६; ४०, १२; ४८, ३; ११; ५४, ७; ५९, ५; ६३, १२; ७०, ६; ८०, ६; १००, ११; **९.** ५२, ४; ८५, २; **१०.** १५, ५; १७, ५; १०; १९, १; ६१, २२; ७३, ११; ७८, ८; ९७, २३; १०३, ११; ११२, १०; १५२, ४; १६५, ३; १७४, १.

अस्मान्ऽअस्मान् **४.** ३२, ४.

अस्माभिः **१.** ११३, ११; **३.** ६२, ७; **६.** ३४, २; **८.** ८१, ८; **१०.** ३८, ३; ११२, ३.

अस्मासु **१.** ४८, १२; ६४, १५; १२३, १३[२]; १३९, ८; **२.** २, ६; २३, १५; **४.** ५१, १०; ५७, २; ८; ५८, १०; **५.** ४, १०; **६.** ७, ३; ४७, ६; **७.** ७७, ६; **८.** ४७, १०; ५९, ७; **१०.** ५९, ५; ६; ८३, ४; १४४, २.

अस्मिं **१.** १६४, ३७; **६.** १९, १२; **७.** २५, ४; १०४, १५; **८.** ७५, १५.

अस्मि **१.** १०५, ७; १२६, ७; **३.** २६, ७[२]; **४.** २६, १; **५.** ४४, १४; **७.** १००, ६; १०४, १६; **८.** १००, ४[२]; **१०.** २७, १; ३३, ७; ४८, ७; ६१, १९; ८३, ५; ६; ८६, ९; ९५, २; ११९, १२; १४५, ५; १५९, ३; १६६, २.

अस्मिन् **१.** १३, ३; ९; ३०, ६; ५१, १५; ५४, १; १००, ६; १०१, ९; १०९, ५; ११४, १; १३२, १[२]; १८५, ७; **२.** ६, ८; १८, ७; ३०, ६; ३५, १४; **३.** २९, १६; ३०, २२; ३५, ६; ६०, ६; **४.** १४, ४; १६, २; २०, १०; ३३, ११; ३४, ११; ३५, १; ५०, १०; ५८, २; **५.** ७५, ८; **६.** ५०, ९; ५२, १३; १६; १७; ५९, ७; ६८, ११; **७.** २३, ५; २९, २; ३२, २६; ६९, ५; ९२, ५; ९५, ४; **८.** २, ३; २२, १८; ४४, १३; ७५, १२; ७६, ७; **१०.** १४, ५; १७, ८; १९, ३; ३८, १; ४३, २; ४४, ५; ९; ७०, ७; ७५, ९; ८५, २७; ९८, ६; १०२, १; १२८, २; ८; १३०, २; १३२, ५; १४५, ४; १४९, ५.

अस्मिन् **१.** ६, ९; ७२, १०; ७३, ४; १८९, ८; **२.** १६, २; **३.** ३८, ७; ५७, ३; **४.** २३, ५; ४१, ४; ४५, १; **६.** १९, ५; ३८, ३; **७.** २१, १; ८७, ५; **८.** २, ३९; १७, १३; ४४, १; **९.** २१, ५; ९४, १; **१०.** ९५, ७; १२४, ४.

अस्मृतध्रू इत्यस्मृतऽध्रू **१०.** ६१, ४.

अस्मे इति **१.** ९, ७; ८; २४, ७;

३०, २२; ३४, ४; ३८, १५; ४३, ७; ४४, २; ४६, ६; ४७, ६; ५४, ११; ७१, २; ७२, २; ७४, १; ७९, ४; ९२, १४; ९३, १२; १०२, २; ११२, २४; ११३, १७; ११४, ९; १०; ११७, २३; ११८, २; ११; १२२, १४; १२४, ९; १२९, ८; १३५, ८; १४१, ११; १५३, १; १५८, २; १६०, ५; १६५, ३; ७; १६७, ९; १६९, ३; १७३, १३; १८४, २; ४; १८६, ११; **२.** ३, ९; ४, ८; ९, ६; ११, ४; १३; १४; २१, ६; ३३, १२; ३५, ४; ३९, ६; ४०, ४; **३.** १, १९; २३; ४, १; ८, ६; १०, ८; ३०, १९; ३५, १; ३६, १०^{२}; ३९, २; ६२, ३^{२}; **४.** ४, ८; ८, ७^{२}; १७, २०; २२, ९; ३२, १४; ३३, १०; ११; ३४, २; १०; ४३, ७; ४४, ६; ४७, ४; ४९, ४; ५०, १०; ११; ५३, ६; ७; **५.** ४, २; ७^{२}; ६, १०; ५३, ९; ५४, १३; ७३, ४; **६.** १, ११; १२^{२}; ६, ७; १९, ९; २३, ८; २८, १; ३५, २; ४४, ९; ४७, १३; ५०, ३; ५२, १६; ६०, ३; ६८, ६; ११; ६९, ६; ७०, २; ५; ६; ७४, २; ३; **७.** ५, ८; २१, ८; २२, ९; २४, ४; २५, ३; २६, ४; ३४, २१; ४२, ६; ४५, ४; ४८, १; ४; ५३, ३; ५६, १७; २०; २४; ५७, ४; ६७, २; ४; ७; ७०, ४; ५; ७५, २; ८; ७६, ७; ७७, ५; ८२, १०; ८३, ९; ८४, ४; ९१, ४; ५; १०१, २; ५; **८.** २, १०; ५, १५; २२, १६; ४७, २; ३; १४; ४८, १०; ५१, १०^{२}; ५४, २; ५७, ४; ६३, १२; ८२, ६; ९७, ८; **९.** १२, ९; ३२, ६; ६३, १; ३०; ६६, २१; ६८, १०; ६९, ७; ८९, १; ९७, ३; **१०.** ६, ६; ७, ४; १०, ३; १७, ८; १८, ९; १९, १; २२, २; १२; १३; ३५, १३; ३६, १३; ३७, ११; ४२, ६; ७; ४४, ५; ६१, २५; ६६, १४; ६९, ४; ७०, ४; ८४, ३; ९१, १५; ९३, १०; ९५, १३; ९८, ३; ९; ९९, ८; १००, ४; १०६, ४; १११, १०; १४०, ४; १४३, ६.

अस्मेराः **२.** ३५, ४.

अ॒स्मेऽहिंतिः **१०.** १०८, १.

अस्मैं **५.** ३९, ५; **६.** २३, ५; ३४, ४; ५; **८.** ४३, २.

अ॒स्मे **१.** ५७, ३; ६१, १–६; ८; १२; १५; **२.** ३५, ५; १२; **५.** ४५, ३; **६.** १, १०; ६३, २; **८.** ४१, १; ९६, १^{२}; **१०.** १४, ९; ४०, ९; ९७, ७.

अ॒स्मै॒ **१.** ३२, २; १३; ५३, १०; ५४, ७; ६७, ४; ६९, ५; ७०, २; ३; ७१, ५; ७६, ३; ७७, १; ९१, २०; १०४, ७; ११४, ११; ११६, ८; १२५, २; १२७, ४; १४७, ४; १४९, ५; १६१, ११; १६२, १६; १६६, ३; १७३, ४; ६; १७८, २; **२.** १२, ५; १३; १३, १०; १४, ६; ७; ९; १६, ४; १७, १; ६; १८, २; १९, ५; २६, ४^{२}; २७, १५^{२}; ३०, २; ३५, २; १०; **३.** १, १०; ९, ९; १३, १; ३१, ११; १२; ५२, ८; ५६, ४; **४.** ४, ६; ७; १८, ७; २४, ६; २५, ५; २७, ३; **५.** २, ३; ३२, १०; ३३, १; ३४, ३; ३६, ६; ४७, ६; ६४, २; **६.** १०, २; १७, ११; १८, १३; २०, ६; २४, ८; ३२, १; ३४, ३; ५; ४०, २; ४२, १; ४४, १४; ५४, ४; **७.** ११, २; १९, २; ३४, ३; ४; ११; १४; ४५, २; ६३, ५; **८.** १, ८; २, ४१; ८, १६; ९, १; १४, २; २३, २१; २७, १८; ३१, २; ६२, १; १००, ९; १०३, ६; **९.** ११, १; ७०, १; ७२, ३; ९१, ३; **१०.** ७, ४; १०, ९; १४, ९; ११; १८, ११; १२; २९, ७; ८; ३१, ४; ११; ४०, ९; ४२, १; ५; ६; ७३, ६; ९; ७९, २; ५; ८२, ४; ८९, ३; ९१, १२; १३; ९६, ६; ९८, ७; ९९, १२; १०२, १०; ११७, ३; १३३, १; १३६, ७; १६०, ३^{२}; ४.

अ॒स्मैऽअ॑स्मै **६.** ४२, ४.

अस्यं **४.** १५, ५; **५.** १७, २; ६४, ३; ८२, २; **६.** ४०, २; **८.** ३१, ४; **९.** ५३, ३; ६१, २९; ६६, १४; ६९, १; ७३, ४; ८९, ३; **१०.** ८, ३.

अ॒स्य **१.** ४, ८; १२, १; २२, १; २३, २; २६, ५; ३३ १; ५२, १२; ५७, ५; ६०, २; ६१, ७; ९–११; १३; १४; ८६, ४; ५; ९२, ६; १०२, १; २; १०५, १–१८; ११६, २५; १२१, ४; १२२, ८; १३१, ४–६; १४३, ३^{२}; १४५, २; १४७, २; १५३, ४; १६४, १; ७; ३२; १६८, ६; १८३, ६; १९०, ३; ४; **२.** ४, ४; ११, २०; १५, १; १६, ७; १९, १; २; २३, १९; २४, १६; २७, ५; ३२, १; ३३, ९; ३५, ६; **३.** १२, १; ३५, ६; ५०, २; ५१, १०; **४.** १, ६; ११; ४, ११; ५, ८; ११; १२^{२}; १५; १७, ९; १४; १९; ३६, २; ४५, १; **५.** १२, ३; १६, ३; १७, ३; ४; २२, ४; २९, ७; ३८, ४; ४३, ३; ४४, ८; ५४, १०; ६३, २; **६.** २९, ५; ३७, २; ४४, १४; ४७, १; ४८, ९; ५९, ५; ६२, १; ६९, १; ७; ७०, २; **७.** ४, ३; ७, ६; २९, १; ३०, १; ३१, ४; ३२, २२; ३८, २; ८; ३९, ३; ४०, ५; ६०, ७; ८७, ६; ९४, १; १००, ५; **८.** १, २६; ३, ८; १२; ५, १४; १३, ४; १५, ५; १७, ११; १९, २; ३; २४, ८; २६, ८; ११; ३७, ३; ४६, १६; ६३, ९; ९२, ६; ९५, २; १०२, ८; **९.** १, १०; २३, ७; ५४, १; ८५, ३; ८; ८९, ३; ९७, १; ९८, ८; १०२, ५; १०८, २; **१०.** ३, ४; ६; ८, ७; १०, ५; ६; २७,

७; ३१, ५; ६^{२}; ४६, ७; ६१, १८; ६४, १३; ९२, १२; ९९, ६; ११; ११०, ११; १११, ३; ११६, २; १२१, ३; १२९, ६; १५१, ६; १६०, १; १६८, २; १८७, ५; १८८, २; १८९, २.

अस्य **१.** ६, २; ७, ७; ८, ८; १०; २२, १७; २३, २४; २७, ८; ३०, ३; ३२, ६; ७; ३३, ११; १३; ३५, ७; ४०, ८; ५०, ३; ५२, ५; १०; १४; ५५, १; ६१, ८; ६२, ६; ६८, ५; ७१, ३; ६; ८०, १०; ८४, ११; १२^{२}; ९४, १; ५; ९५, ३; १०३, १; ३; ५; ११०, ६; ११४, ४; ११५, ५; ११९, २; ५; १२१, १०; १२७, ५^{२}; ६; १२८, ५; १३८, १^{२}; १४०, ३; ५; १४१, २; ४; ८; १४६, १^{२}; १४६, १; २; १४८, २; ४; १५२, ३; १५४, ५; १५५, ३; ४; ५^{२}; १५६, २–४; १५८, ५; १६०, ३; १६२, ८^{२}; १६३, २; ९^{२}; १२; १६४, १; ७; १८; १७६, ४; १९१, १०–१३; **२.** ३, ११^{२}; ४, ४; ५, ४; ५; ११, ९; १०; १२, १३; १३, १०; १४, १; २; १०; १५, १; १७, १; ३; १८, ८; २०, ८; २२, २; ३५, २; ८; ११^{२}; ३६, ५; ३८, २; ५; ७; **३.** १, ७; ९; ११, ३; १३, ५; २४, १; २९, ३; ३०, १२; १७; ३२, ४; १५; ३४, ६; ७; ३६, ५^{२}; ३८, ५; ७; ४२, २; ४८, २; ५०, १; ५१, ४; ५; ५५, १८–२०; ५६, ७; **४.** १, ७; ९; १०; ६, ५; ७, १०; ९, ६; १६, १; ५; १७, ६; ११; १२; १८, ४; २३, २^{२}; ३^{२}; ४–६; २५, ५; ७; २७, ४; २९, ३; ३०, १३; ३८, ८; ४०, ३; ५०, २; ५४, ४; ५८, ३^{२}; **५.** २, १; १०; १९, ५; २९, ३^{२}; ६; ११; ३०, २; ९^{२}; १०; ११; ३२, ५^{२}; ९^{२}; ३३, ८; ३४, ४; ७; ३७, ३; ४५, ९; ४७, ४; ४८, ४^{२}; ५३, १६; ५४, ७; ६०, ६; ६२, ७; ७७, ४; **६.** ३, ४; १२, ५; १८, ५; १२; १९, ४; २२, ३; २४, ७; २७, १^{४}; २^{४}; २८, २; ३०, १; २; ३५, १; ३६, २; ३७, ४; ३८, २; ४४, ५; १३; ४५, ३^{२}; ४७, १८^{२}; ५१, १३; ५२, ३; ५४, ३; ६२, ९; ६३, १; ७५, ५; ८^{२}; **७.** ३, ५; ११, ४; १६, ३; २०, ६; ३२, १२; ३४, ७; १७; ३६, ५; ४०, १; ४५, २^{२}; ८२, ३; ६; ८६, १; ८८, २; ९०, २; ९८, २; ५; १००, ३; ४; १०४, ११; **८.** १, ३४; २, २१; ३, ४; ८; १०; १३; ४, ८; ६, ४; ५; १३; १२, ७; २४; ३२; १३, ८; २९; १९, १४; ३२, १५; ४०, ६; ४८, १२; ४९, २; ५०, २; ५१, ५; ६०, १३; ६३, ३; ६६, ८–१०; ६९, ३; १७; ७२, १; २; ६; ७५, ७; ८२, ७; ९२, ५; ९४, ४; ९५, ६; ९७, १; ९९, ४; १०३, ९; **९.** ६, ७; ७, १; ७; ८; ८, १; १४, ३; २९, १; ३०, १; ४७, २; ३; ७०, ३; ७१, २; ५; ८; ७८, १; ८३, २^{२}; ३; ४; ८५, १२; ८६, १४; १५^{३}; ८८, १; ८९, ६; ९२, २; ९६, १; २; २२; ९७, ५४; ९९, ३; १०२, ३; १०८, १२; १०९, १५; **१०.** १, ३^{२}; १०, ५; १२, ५; ८; १३, ५; १६, १; २०, ६; ९; २३, २; ३; ६; २७, १०; २०; २४; २९, ५; ३४, ४; ६; ४२, ६; ४३, ७; ४८, ९; ५५, २; ६१, १; ३; १३; २४^{२}; ६२, ११; ६९, २; १०; ७३, ९; १०; ७५, ९; ७६, ३; ७; ७९, १; ८६, ४; ५; ८८, २; ८९, ६; ९०, ३^{२}; ४; ६; ११; १२^{२}; १५; ९१, १३; ९२, ३^{२}; ७; ८; ९६, ३; ७; ९९, २; ९^{२}; १०; १०२, ६; ७; १११, ७; ११३, १; २; ११४, ७; १२३, ७; १२४, ७; ८; १२५, ७; १२९, ७; १३२, ३; १३५, ७; १३८, २; १४२, ५; १४७, ४; १४९, ३; १६०, ४; १६८, १; ४; १७८, ३.

अस्यत् **१०.** ६१, ८.

अस्यतं **७.** १०४, २५.

अस्यति **२.** २४, ८.

अस्यति **३.** ५३, २२.

अस्यतु **१.** ११४, ४.

अस्यथ **१.** ३९, १; १७२, २.

अस्यथ **५.** ५५, ६.

अस्यध्वं **१०.** ३०, २.

अस्यन् **४.** २२, २; **१०.** ४२, १; १६८, १.

अस्यसि **५.** ८४, २.

अस्याः **१.** ८७, ४; १२१, ६; १४; १३१, ६; १३८, ४; १६४, ३७; **३.** ८, १; १५, २; **४.** १, ५; ३, ४; ४, ३; २३, ५; ४१, ५; **५.** ३, ८; ४१, १७; ४५, ८; **६.** १, १; **७.** ३६, ८; **८.** ४६, २१; ६६, १४; **९.** ७५, २; **१०.** २९, २; ११०, ४; १२२, ७.

अस्याः **१.** ३२, ९; ४८, ३; ८; ९२, ५; ११३, २; १२४, ८; **३.** ५७, १; **४.** ३०, ११; ३३, ४; ४२, ८; ९; **५.** ४६, १; **६.** ७५, ११; **७.** ७८, १; **८.** १००, १०; **१०.** ८५, १०; २८; ३९; ८६, ११; १०२, २; १०९, ३; १४५, ४.

अस्यान् **९.** ८९, १.

अस्यां **२.** ३, ४; **६.** २६, ८; **७.** १९, ७; २०, ८.

अस्यां **३.** ५७, २; **१०.** ८५, ४५.

अस्यै **१.** १२७, ११; १५८, २; **२.** २३, ७; ३३, ५; **७.** १, १९; **९.** ९७, ३०; **१०.** ९७, १९.

अस्यै **१०.** ८५, ३३.

अस्रवः **६.** ६१, ३.

अस्रवंतीं **१०.** ६३, १०.

अस्राक् **४.** ५३, ३; ४.

अस्रिधः **१.** ३, ९; १३, ९; **४.** ४५, ४; **५.** ४६, ४; **८.** ५०, ८.

अस्रिधं **१.** ८९, ३; **९.** ८६, १८.

अस्रिधा **३.** ५८, ७; **४.** ३२, २४.

अस्रिधानैः **७.** ६९, ७.

अस्रेधता **३.** १४, ५.

अस्रेधत्ऽभिः **८.** ६०, ८.

अस्रेधन् **९.** ९८, ९.

अस्रेधंतः **३.** २९, ९; **७.** ५९, ६.

अस्रेधंती **५.** ८०, ३; **८.** २७, १८.

अस्त्रेमा **१०.** ८, २.

अस्त्रेमाणं **३.** २९, १३.

अस्वदयत् **२.** ४, ७.

अस्वनीत् **४.** २७, ३.

अस्वंप्नऽजः **२.** २७, ९; **४.** ४, १२.

अस्वं **१.** ११२, ३; **१०.** ६१, १७.

अस्वरन् **५.** ५४, ८; **८.** १२, ३२.

अस्वरन् **८.** ३, ७; १६; ९७, ११; **९.** ४५, ५; ६३, २१; ६६, ८; ६७, ९; ७३, १; ४; १०१, ११; १०६, ११; ११०, ८.

अस्वंऽवेशं **७.** ३७, ७.

अस्वाः **१०.** १४८, ५.

अस्वापयत् **४.** ३०, २१; **९.** ९७, ५४.

अस्वाष्ट्रां **२.** ११, ७.

अहं **१.** ६, ४; ४८, ४; ५२, ११; ८४, १५; ९२, ३; ११९, ३; ८; १३५, ८; १४०, ९^{२}; १४६, ५; १४७, ३; १५१, ७; १५४, ६; **२.** १०, २; २५, ३; ३१, ७; **३.** ३३, ११; ३६, ४; **४.** २२, ७; ३०, ७; १०; **५.** ३, १२; ७, ५; ९, ५; ३४, ३; ५२, ६; ५४, ४; १०; ८३, ३; **६.** ३८, ४; **७.** २०, २; १०३, २; **८.** ११, ४; २०, २०; २८, १; ३३, १७; ४३, ३; ८; **९.** ७७, २; **१०.** २८, १; ४२, ८; ४३, ६; ५१, २; ६१, १९; ७१, ८; ८६, २; ८९, १३; १८९, ३.

अहंऽइव **७.** ३४, ५.

अहंः **३.** ४८, २; **६.** ९, १; **७.** ६६, ११.

अहंःऽअहः **१.** १२३, ९; **२.** ३०, १; **८.** २४, २४; २६, १२; **१०.** ५२, २; ३.

अहंःदिवि **९.** ८६, ४१.

अहःऽदृशः **८.** ६६, १०.

अहंऽभिः **१०.** १४, ९.

अहःऽविदः **१.** २, २.

अहःऽविदं **१.** १५६, ४.

अहःऽविदा **८.** ५, ९; २१.

अहतं **१.** ११६, २१; ११७, १६; **६.** ७२, १.

अहंतये **९.** ९६, ४.

अहंन् **१.** ३२, १–५; ३४, ३; ५६, ५; ६९, ४; ८५, ९; १००, ६; १०१, २; १०३, २^{२}; ११७, १२; १३२, २; १८६, ४; **२.** ११, ५; ३२, २; **३.** ४, २; ३२, ११; ३४, ३; ४७, ३; **४.** १२, १; १६, ११; २८, १; ३; ३०, ५; ५४, ६; **५.** २९, ३; ३०, ७; **६.** २६, १; ४७, २१; **७.** १९, ५; **८.** ३२, २६; **९.** ८६, १८; **१०.** ६१, १; ६८, ११; ९५, १; ११; १३३, २; १४७, १.

अहन् **१.** ३३, ११; ६३, ३; ८०, १०; **३.** ३३, ६; **४.** १६, ७; ३०, १४; **६.** २६, ३; ४; ६; **७.** १९, ५; **१०.** ७३, ६; १०२, ७.

अहनं **१०.** ४८, ६.

अहना **१.** १२३, ४.

अहंनि **१.** ११०, ७; १३२, १; **१०.** १८, १४.

अहंनी इति **१.** १२३, ७; १८५, १; **४.** ५५, ३; **५.** ८२, ८; **६.** ५८, १; **१०.** ३९, १२; ७६, १.

अहन्यः **१.** १६८, ५; १९०, ३.

अहन्यैभिः **५.** ४८, ३.

अहंऽभिः **१.** ५१, ९; १६४, ५१; **४.** ४५, ६; ५३, ७; **५.** ६२, २; **७.** २८, ४; **९.** ५५, ३; **१०.** ७, ४; १०, ९.

अहंऽभ्यः **७.** ८७, १; **१०.** ८९, ११.

अहं **१.** ११, ६; १७, १; ७; २३, २२; ३३, २; ४४, ५; ५०, १३; १०५, ७; १२०, ६; १०; १२६, ७; १३८, १; १६५, ६; ८; १०; १७१, ४; १७९, १; **२.** १४, १०; २७, १७; २८, ९; ११; २९, ७; ३२, ४; **३.** १५, १; ४३, ३; ५३, १२; **४.** १८, २; २६, १^{४}; २^{३}; ३; २७, १; ४२, २–६; **५.** २, ८; ९, ६; १२, २; ३; ४२, २; ४३, ९; ४४, १४; ७५, २; **६.** ९, २; २६, ७; ४७, १०; ५०, ९; **७.** २९, ४; ३२, १८; ८६, ७; ८९, १; १०४, १४; **८.** १, २०; ३१, ६; १०^{२}; ११; ४६; ९, १३; १६; १०, २; १४, १; २; १९, २५; २८; ३५, २२; ३८, १०; ४४, २३^{२}; ४५, ३५; ५३, ८; ६२, ११; ६७, १०; ७४, १३; ७५, १५; ७६, १२; ७८, १०; **९.** ९६, ४; १०७, १९; २०; ११२, ३; **१०.** १५, ३; १८, १३; २५, ३; २७, १–३; ५; ९; २८, ५; ३४, २; ३; १२; ३८, ५; ४०, ७; ४८, १^{२}; २^{२}; ४–६; ८^{२}; ४९, १^{३}; २^{२}; ३^{३}; ४; ५^{३}; ६; ७; ८^{२}; ९^{२}; १०; ५१, ४^{२}; ५२, २; ६०, १०; ६१, १८; ७९, ४; ८३, ५; ८६, ९; ११; १२; १४; ८८, १५; ९५, २^{२}; ९७, १; ११; २०; १०८, १०; ११९, ५; ९; १०; १२; १२५, १^{४}; २^{३}; ३; ५; ६^{३}; ७; ८; १२८, ४; १४५, ३; ५; १४६, ६; १४९, ५; १५०, ४; १५९, १; २^{३}; ३; ६^{२}; १६६, २; ४^{२}; ५; १६७, ३; १७४, ५; १८३, ३^{४}.

अहंऽपूर्वः **१.** १८१, ३.

अहंऽयुः **१.** १६७, ७.

अहंऽसन **८.** ६१, ९.

अहंये **५.** ३१, ४; **७.** १०४, ९; **८.** ९६, ५.

अहुरिति **१.** ७१, २; **६.** ९, १; ४८, १७; **७.** १०३, ७; **१०.** १६८, ३.

अहर्यंत **१०.** ९६, १०.

अहर्यथाः **१०.** ९६, ५.

अहर्विः **१.** १८२, ३.

अहंऽसु **१.** १२४, ९.

अहस्तः **१.** ३२, ७.

अहस्तं ३. ३०, ८.
अहस्ता १०. २२, १४.
अहस्तासः १०. ३४, ९.
अहा १. ५०, ७; ११६, ४; १३०, २; ९; १४०, १३; ३. ३२, ९; ५४, २२; ४. ३०, ३; ५. ४८, ३; ७. ३०, ३; ६५, २; ८. १, ३; ४३, ३०; ६१, १७; १०. १२, ४; ३२, ८.
अहाऽइव ४. ३३, ६; ५. ५८, ५; ६. ६१, ९; ८. ९६, १९.
अहाः १. ११६, ३.
अहानां ८. २२, १३.
अहानि १. ५२, ११; ८८, ४; १७१, ३; ३. ३४, ४; १०; ५. ४९, ३; ५४, ४; ७. ११, २; २५, ४; ७६, ३; १०. १८, ५; ३१, ७; ३७, २.
अहानिऽइव ८. ४८, ७.
अहापि १०. १६१, ३; ५; १७३, १.
अहावि ५. ८६, ६; १०. ९१, १५.
अहासत १. ९, ४; ८. ७, २; ९. ७३, ६.
अहिंसंतीः १०. २२, १३.
अहिंसानस्य ५. ६४, ३.
अहिंस्यमानः १. १४१, ५.
अहिः १. ३२, ५; ८; १३; ७९, १; १८६, ५; २. ३१, ६; ५. ४१, १६; ६. ४९, १४; ५०, १४; ७. ३५, १३; ३८, ५; १०. ६४, ४; ६६, ११; ९२, १२; ९३, ५.
अहिःऽइव ६. ७५, १४.
अहिःऽगोपाः १. ३२, ११.
अहिऽघ्ने ६. १८, १४.
अहिऽघ्ने २. ३०, १.
अहितेन ८. ६२, ३.
अहिना २. ११, २; ४. १७, १; ५५, ६; ७. २१, ३; १०. १११, ९; ११३, ३.
अहिऽनाम्नां ९. ८८, ४.
अहिन्वन् ३. ३१, ५.
अहिऽभानवः १. १७२, १.
अहिं १. ३२, १; २; ५१, ४; ८०, १; १३; १०३, २; ७; १८७, ६; २. ११, ५; १२, ३; ११; १५, १; १९, २; ३. ३२, ११; ३३, ७; ४. १७, ७; १९, ३; ९; २२, ५; २८, १; ५. २९, २; ३; ८; ३०, ६; ३१, ७; ३२, २; ६. १७, ९; १०; २०, २; ७२, ३; ७. ३४, १६; ३८, ७; ८. ३, २०; ९३, २; १०. ९६, ४; ११३, ८; १३३, २.
अहिऽमन्यवः १. ६४, ८; ९.
अहिऽमायस्य ६. २०, ७.
अहिऽमायाः ६. ५२, १५; १०. ६३, ४.
अहिऽमायान् १. १९०, ४.
अहिऽशुष्म ५. ३३, ५.
अहिऽहत्याय १. १३०, ४.
अहिऽहत्ये १. ६१, ८; १६५, ६; ३. ३२, १२; ४७, ४.
अहिऽहन् २. १३, ५.
अहिऽहनं १. ११७, ९; ११८, ९.
अहिऽहा २. १९, ३.
अहीनां १. ३२, ३; ४.
अहीनां १०. १३९, ६.
अहीशुवः १०. १४४, ३.
अहीशुवं ८. ३२, २; २६; ७७, २.
अहुवंत ८. ३८, ९.
अहुवे २. ३७, २.
अहूताः १०. १०७, ९.
अहूमहि ६. ४५, १०; ८. २४, १८.
अहूषत १. १४, २; ४५, ४; ४९, ४; ८. ८, १८.
अहृणानः ७. ८६, २; १०. ११६, ७.
अहृणीयमानः १०. १०९, २.
अहृणीयमाना ५. ६२, ६.
अहृषत १०. १५५, ५.
अहेः १. ३२, १४; ५२, १०; ८. ९३, १४; १०. ४८, २.
अहेतन ८. ४७, ६.
अहेम ७. ७३, ३.
अहेम २. १९, ७; १०. ८८, ५.
अहेषत ९. २२, १; ७१, ५; ७२, २; ८६, २५.
अहेळता २. ३२, ३; ७. ६७, ७; १०. ७०, ४.
अहेळन् १. ९१, ४; १०. ३२, ८.
अहेळमानः १. २४, ११; १३८, ३; ४; ६. ४१, १.
अहेळयन् १०. ३७, ५.
अहोभिःऽइव १. १३०, १०.
अहोरात्राणि १०. १९०, २.
अह्नः १. ११६, १९; १२३, ९; ३. ३२, १४; ५६, ६; ४. १०, ५; १६, १२; ३३, ११; ५४, १; ५. ७६, ३; ८. २२, ११; ९. ८६, १९; १०. १०, ६; ४२, ५; ९५, ५; १६; १२९, २; १३०, ५.
अह्नवाय्यं ८. ४५, २७.
अह्ना ४. १६, ३; १०. ३७, १०.
अह्नाऽअह्ना १०. ३७, ९.
अह्नां १. १२६, ३; १८५, ४; २. १९, ३; २१, ६; ३. ८, ५; २३, ४; ३४, ४; ४. ३४, १; ५; ३५, ६; ३७, १; ५. १, ४; ५; ३, ६; ८०, २; ६. ७, ५; ३९, ३; ७. ५, ५; ४१, ४; ७७, २; ८८, ४; ९. ८६, ४२; ४५; ९७, ३०; १०. ७०, १; ८५, १९; ८८, १२; ११०, ४.
अह्ने ९. ९२, ५; १०. ४०, ५; ९.
अह्यः ९. ७७, ३; १०. १३८, १; १४४, ४.
अह्यन् ६. ४०, २; ९. २६, ३; ४.
अह्यपूर्णां २. ३८, ३.
अह्रयः १. ७४, ८; ८. ७०, १३; ९. ५४, १; १०. ९३, ९.
अह्रयं ३. २, ४; ५. ७९, ५; ७. ६७, ६; ८. ५४, ८; ५६, १; ६०, १६.
अह्रया ५. ७९, ६; ८. ८, १३.
अह्रयाण ४. ४, १४.
अह्रयाणं १. ६२, १०.
अह्रयाणा ७. ८०, २.
अह्रये १०. १४७, ३.
अह्रुतः ६. ६१, ८; १०. ५६, २.
अह्रुतऽप्सवः १. ५२, ४; ८. २०, ७.
अह्रुताः ९. ३४, ६.
अन्हत् १. २४, १२; १३; ८. ८, ९.
अन्हत् १. १०६, ६.
अन्हंत ४. ६, ९; ५. २९, ८; १०. १२२, ८.
अन्हयत् १. ११७, १८; १९.
अन्हयंत १०. १७, ७.
अन्हयेतां १०. ५४, १; ५५, १.
अन्हाम ६. ५०, ४.
अन्हे १. ६९, ३.
अन्हे १. ५२, ३; २. ३२, ८; ३. ३३, ६; ५६, ४; ७. ७४, १; ८. १३, ३; २२, १; ३८, ९; १०. ३९, ६.

आ

आ १. १, २; ५; ७; २, १; ४–६; ३, ३–८; ४, २–४; ७; ५, १; ३[२]; ७; ६, ९; ७, २; ३; ८, १; ३; ९, १–३; १०; १०, २; ४[२]; ११; १२, ३; ४; १०; ११; १३, १; ४; १४, १; २[२]; ६; १२; १५, १; ४; १६, १; ४; ५; ९; १७, १; ३; ८; १९, १–९; २०, ७; २१, ४; २२, १; ८–१०; २३, १; ७; १३[२]; २३; २४, ११; १२; २५, ५; १०; १५[२]; १९; २६, ३; ४; २७, ५[२]; ६; १३; २८, ९; २९, १–७; ३०, १; २; ८; १०; १४; १५[२]; १७; २१[२]; २२; ३१, ४[२]; ७; ९[२]; १७[२]; ३२, ३; ६; ७; १०; ३३, १; ७; ११; ३४, ५; १०–१२; ३५, २[२]; ३; ४; ७; ८; ३६, ६; ३७, ६; १३; ३८, ७; १०; ३९, ६–९; ४०, २; ४; ४१, ८; ९; ४२, ५; ४३, ८; ४४, १; ७; ९; १३; ४५, २; ८; ९; ४६, ७; १३; ४७, २; ७–९; ४८, ५; ९; ११; १२; १६; ४९, १; ५०, ४; ५१, २; ४; १०[२]; १२[२]; ५२, १; ४; ६; ८; १२; १३; ५३, ३; ५५, ७[२]; ५७, ३; ५; ५८, १; २; ५; ६; ५९, ३; ६०, ३; ४; ६१, ९; १६; ६२, ८; ६३, २[२]; ५; ६; ९; ६४, ९[२]; १३; ६७, ४; ७०, १[२]; ७१, ४; ६[२]; ८; ७२, ४; ८; ९; ७३, ४; ७४, ६; ७६, २–४; ७७, २; ५; ७९, २; ८; ९; ८१, ४; ५; ७; ९; ८३, ४; ५[२]; ८४, १[२]; ३; ९; १८; २०; ८५, ४; ६[२]; ७; ११; ८६, ५; ८७, २; ८८, १[२]; २; ४; ८९, १; ७; ९१, ११; १३; १६; १७; २२; २३; ९२, ३; १३; १५; १६; १७[२]; १८; ९३, ६; ११; १२; ९४, ३; ८; ९५, ४; ९७, १; ९८, २; १०१, ८; १०; १०२, ५; १०४, १; २; ६[२]; ९[२]; १०५, १; २; ५; १३; १४; १०६, २; १०७, १; २; १०८, १; ३; ४; ७–१२; १०९, ४; ७; ११०, ३; ६; ९; १११, २–४; ११२, १–२५; ११३, १; २; १०; १४; १६[२]; १९; ११४, ३; ४; ९; ११५, १; ३; ११६, १६; १७; १९; २२; ११७, १; १७; १९; २३; २५; ११८, १; २; ४; ५; १०; ११; ११९, १; २[२]; ३–५; ७; ९; १२०, ६; १२१, १; ५; १०; १५; १२२, ५[२]; १४[२]; १२३, १; २; ४; १२; १२४, ४; ५; १२५, ७; १२६, २; ३; ५; १२७, ७; ८[२]; ११; १२८, ६; १२९, ६; ७[२]; ९[२]; १३०, १; २; ९; १३१, ६; १३२, ४; १३४, १[२]; ३; ४; १३५, ३; ४[४]; ५[२]; ६; ७; १३६, ३; १३७, १[२]; २; ३; १३९, १; ६[२]; ९[२]; १४०, ३; ७; ११; १४१, २[२]; ४; ५[२]; ७; ११; १४२, १; ३; ४; ७[२]; १३[२]; १४३, ४; १४४, २; ३; ५; १४५, ३; १४८, ४; १४९, १[२]; ३; १५०, १[२]; १५१, ३; ४; ५[२]; ६; १५२, ३[२]; ६; ७; १५५, ५; १५६, ३; ५[२]; १५७, ३; ४; १५९, ४; १६१, १–४; १०; १६२, ५; ११; १६; २०; १६३, ७; १३; १६४, ८; ११; १३; १६; २१; २७; ३०; ३१[२]; ३२; ३३; ३७; ४७; १६५, २; ४; ९; १२; १४; १५; १६६, ४; ९; १३–१५; १६७, २; ५; ६; ११; १६८, १; ३; ४; १०; १७१, २; १७३, १; ३; ११; १३; १७४, ८; १७५, २; १७६, १; २; १७७, १[२]; २[२]; ३; ४; १७८, १; २; १७९, ४; १८०, ५; ६; १८१, २[२]; ३; ६; १८२, ८; १८३, ३–६; १८४, ६; १८६, १; २; ४; ६; ९; १८७, ३; १८८, ३; ६; ९; १८९, ४; १९१, १०; **२.** १, ८; १२; १६; २, २; ४[२]; ६; १३; ३, ३; ८; ११; ४, ३[२]; ५[२]; ६; ५, २; ५; ६, ६; ८[२]; ७, १; ८, ३, ४; ९, २; १०, ५; ११, १५; १२, ५; १५[२]; १३, १; २; ६; ९; १४, १; ३; ७; १५, २; १६, ८; १७, २; ४; ६; ७[२]; १८, ४[४]; ५[४]; ६[२]; १९, ५[२]; २२, २; २३, १; ३; ९; १६; २४, २; ७[२]; २६, २; २७, ५; १६; १७; २८, ९; ११; २९, ६; ७; ३०, १; ७; १०; ३२, ३; ३३, १; ६; ३४, ४–६; ८; ३५, २; ७–९; ३६, १–६; ३८, १–७; ८[२]; ११; ३९, २; ५; ४१, १–३; ९; १३[२]; १९; २१; ४३, २[२]; ३; **३.** १, १७; १९; २२; २, ४; ७[२]; १२; १३; ३, ३; ४; ९; १०[२]; ४, १; ६; ८[२]; ११; ५, ३; ७; ९; ६, २; ४–७; ९; ७, १–४; ९; ८, ४; ५; ९; ९, ५; ८; १०, ४; ११, ९; १२, १; ५; १३, १[२]; ४; १४, १; २[२]; ३; १६, ४[४]; ५; १९, ४; २१, ४; २२, २; २३, १; ४; २४, ३; २५, २; ३; २६, ५; २७, ६; ९; २९, १; ६; १०; १५; ३०, १; २; ११; १३; १७; १९[२]; २१; ३१, ३; ५; १४[२]; ३२, २; ५; १०; १३[२]; १५; १६; ३३, ८; १०–१३; ३४, १[२]; ५; ३५, १; २[२]; ६[२]; ९; ३६, ९; ३७, १; ९; ११[२]; ३८, ४; ७; ८; ३९, १–३; ५; ४०, २; ४१, ३; ४२, २; ४३, १; २[२]; ३; ४; ६; ७; ४४, १[३]; ४[२]; ४५, १; ४; ४६, ४; ४७, १; ३; ४८, २; ४९, १; ५०; १[२]; २; ५१, ३; ७; ५२, २; ५३, १–३; ५; ८; ११; १४; १५; २०[३]; ५४, ११[२]; १५[२]; ५५, १६; १८; ५६, २; ५; ६[३]; ५७, ५; ५८, १; २; ४[२]; ९; ५९, ३; ५; ६०, ३; ५; ६१, २; ३; ४[२]; ६; ७; ६२, ५; १५; १६; **४.** १, १–३; ७; १७; २, ३; ४; ७; ८; १८; ३, १; ९; ४, ३; ४; ९; ५, १५; ६, ६; ९; ७, ४; ६; ९, १; ११, १[२]; ५; ६; १२, २; १४, १–४; १५, २; ८; १६, १; ५; ८; १०; १८; १७, २४; १६; १८; १८, १; ५; १३; १९, ९; २०, १[२]; १०; २१, १; ३; ५; ६; २२, १; ४[२]; ८; २३, ६; ९; २४, १; २; ८; २५, ७; २८, ५; २९, १;

२; ३०, ३; ७; ११; १६; २३; ३१,
१; ४; ५; ३२, १; २[२]; ५; १०;
१२; १५[२]; १८; २०; २१; ३३, ७;
८; ३४, २; ३; ५[२]; ६; ३५, २;
६; ३६, २; ७; ८[२]; ३७, ८; ३८,
१०; ४१, ११; ४२, ८; ४३, ४;
५; ४४, ३; ५; ४५, २[२]; ३; ४६,
३–५; ४७, १; ३; ४८, १–५; ४९,
३; ५०, ३; १०; ५१, ८; १०;
५२, ५; ७[२]; ५३, ३; ७; ५४, ४;
५५, ५; ९; १०; ५७, १; ५८, ३;
५. १, ७; १०[२]; ११[२]; २, ५; ८;
४, ४; ५; ५, ७; ९; ६, १; ४;
८; ७, ३; ४[२]; ७; ९[२]; १०; ९, ७;
१०, १; २; ७; ११, ५; १२, ६; १३,
३; ६; १६, ५[२]; १७, १; ४; १९, २;
३; ५; २१, ४[२]; २३, १; २; ४; २६,
१; २; ४; ५; ९; २८, ३; ६; २९,
२; ११; ३१, २; ३; ९; १२; १३;
३३, ३; ५; ३४, २; ५; ७; ३५,
१–३; ८; ३६, १; २; ३७, ३[२];
४; ३८, ४; ३९, १–३; ४०, १;
८; ४१, ३; ६; ७; १३; १४; १७;
४२, १८[२]; ४३, १; २; ६[२]; ७; ८;
१०[२]; ११[२]; १२[२]; १३; ४४, ६; ४५,
२; ६; ९; १०; ४६, ५; ६; ८; ४७,
१; ३; ४८, १; २; ३[२]; ४९, १[२];
५; ५०, ३; ५१, १–३; ५; ८;
५२, २; ६[२]; ७; १२; ५३, २; ६;
८[२]; ५४, १; ३; ५५, ३; ५६, १;
३; ८[२]; ९; ५७, १; ५८, ३; ५९,
१; ६; ८; ६०, २; ६१, १२; १६;
६२, २; ८; ६३, ७; ६४, ५[२]; ७;
६६, १; ६; ६७, २; ५[२]; ६९, ४;
७१, १; ३; ७२, १; ७३, १; ४;
५; ९; ७४, १; २; ५–७; ८[२]; ७५,
३; ६; ७; ९; ७६, १; ३[२]; ४; ७७,
३; ७८, १; ४; ७९, ६–८; ८०,
५; ८२, ५; ७; ८३, १; ६; ७;
८५, ६; ८६, ३; ८७, ३; ७; ८;
६. १, ६; १०; ११; ३, ३; ७; ४,
६; ५, २; ६, ६; ७, १[२]; ५; ८,
४; ९, ४; १०, ४; ११, १; १२,
२; ४; १३, २; ५; १५, १; ३;

५; १७; १८; १६, ६; १०; १६;
१९; २९; ३१; ३५; ३६; ४०; ४१;
४२[२]; ४४; ४६; १७, १२; १३;
१८, ९; ११; १९, १; ३; ६–८;
९[४]; २०, ८; २१, ४; १०; ११;
२२, ३; ८; १०; ११[२]; २३, ८;
२८, १; ३; २९, २[४]; ३; ५; ३०,
२; ३१, १; २; ५; ३२, ४; ३३,
३; ३५, ५; ३६, ३; ३७, ५; ३८,
२[२]; ५; ४०, १; ३[२]; ४; ४१, १;
४; ५; ४२, २; ३; ४४, १२; १९;
२०; ४५, १; २१; ३३; ४६, ५[२];
७[२]; ८; १४; ४७, ६; ९[२]; २०;
३०[२]; ३१; ४८, ६[२]; ११; १५; १६;
४९, १; ६; ११; ५०, ४; ८–१०;
५१, १; २; ८[२]; ९[२]; १५; ५२,
१६; १७; ५३, ७; ५४, ७; १०;
५५, १; ६; ५६, ६; ५७, ५; ५८,
४; ५९, २; ५–१०; ६०, ३;
८; ९; १४; १५; ६१, २; १४;
६२, २; ५; १०; ११; ६३, १; ३;
७; ११; ६४, ४; ५; ६६, ३; ५;
६; ११; ६७, ३; ६; ७; ८[२]; ६८,
१; ११; ६९, ३; ७; ७१, ४; ७२,
३; ७३, १; ७५, ३; १३; **७.** १,
८; १७; १९–२१; २४; २५; २,
६; ३, ९; ४, ५; ८; ५, ४; ८; ६,
२; ६[२]; ७[२]; ७, २[२]; ३; ५; ६[२]; ८,
१; ९, ३; १०, १; २; ४; ११, १;
२; ५; १२, २; १३, २; १४, ३;
१५, ११; १६, १; ४; ६; ८; ९;
१७, २; ६; १८, ४; ७[३]; २०, २;
४; ७; ९[२]; २१, २; २२, ३;
२३, १; २४, ३[२]; ४; २५, १; २;
२७, १; ५; २८, २; २९, १; ३;
३०, १; ३२, १; २; ४[२]; ५–७;
१३; १४; १९; २०; २४; २६; ३३,
२; १४; ३४, ४; १०; २०; ३६,
१; ३; ४; ६; ३७, १; ५; ८[२]; ३८,
२; ३; ३९, २; ५[३]; ४१, ६; ४२,
३–५; ४३, ३[२]; ४[३]; ५; ४४, ५;
४५, १; ३; ४६, ४; ४८, १; ५०,
१[२]; ५३, २; ५६, १०; १३; १८;
१९; २१; ५७, २; ३; ७; ५८, ५;

५९, ४; ६; ७; १०; ११; ६०, ४;
८; ६१, १; २; ६२, ३; ५[२]; ६४,
२; ६५, ४[२]; ६६, १५; १७–१९;
६७, ४–६; १०; ६८, १; ४; ६९,
१–३; ७०, १[२]; ५; ७१, ३[२]; ४;
७२, १; २; ५[४]; ७३, २; ४; ७४,
३; ४; ७५, १; ३; ७६, २; ७७,
४; ७८, ४; ७९, २; ८१, ५; ८२,
३; ६; ८; ८३, ३[२]; ५; ८४, १;
८७, २; ८८, ३; ४; ९१, ४; ६;
९२, १; ९३, ६[२]; ९४, ४; ७;
१०; ११; ९५, २; ५; ९७, २[२];
४; ५; ९८, ३; ९९, ७; १०४, ९;
८. १, ४; ९; १०; १६–१८;
२३[२]; २४[२]; २५; २७; २९; ३१;
२, १४; १७; २२; २५–२७; २८[२];
३, २; १४; १७; ४, २[२]; ३; ८;
१०–१२; ५, ७; १०; १३; १५;
१६; २४; २८; ३०; ३१; ३२[२];
३३; ६, १६; २३; २४; ३६; ४६;
७, ११; १३; २७; ३३; ३५; ८,
१; २; ३[२]; ४[२]; ६[२]; ७; ९–११; १३;
१७; १८; ९, १; ७[२]; ८[२]; १४;
१६; १८; २०, १; ५; ११, १[२];
७; १०; १३, ५; ११; १३; १४;
१४, ६; १५, १; १६, ३; १७,
१[२]; २; ४; ५; ११; १३; १८, ४;
७; ११; १६[२]; १९, १; ४; १५;
२७; २८; ३१; ३२; २०, १; २[२];
५; ६; १०; १६; १८[२]; २२; २३;
२६; २१, ३; ४; ८[२]; १०; १६;
२२, १[२]; ४; ५; ८–१०; १२[२];
१५; १७; १८; २३, १०; १२;
३०; २४, १; ४[२]; ६[३]; १०; १३;
१६; २५; २८; २९; २५, ४; ६;
१८; २६, ४; ५; ८; ९; २०;
२१; २३; २७, २; ५; ६; ८[२];
११; १८; २०; २२; २८, १; ४;
२९, २; ३१, ५; १०; ११; ३२,
६; ८; १२; १८; २३; २४; ३३,
२; ३; ८; ९; १२[२]; १३; १४;
१६; ३४, २; ४; ६–8; १०[२]; १२–१६;
१८; ३५, ४; १०; ३८, ४; ७; १०;
३९, ७–९; ४०, १; २[२]; ४१, ८;

४२, १; ४; ४४, १; ३; ९; १३;
४५, १; ३; ४; १४; १५; २०[२];
२३; ३६; ३९; ४०; ४६, ३; ७;
९; १९; २१[२]; २५; ३०; ३२;
४८, ४; ६; ११; १३–१५; ४९,
३–५; ७; ५०, ३–५; ७; ५२,
७; ५३, ३[२]; ४[२]; ५[२]; ५४, ३[२];
६; ५५, १; ५७, १; ६०, १[२]; ४[२];
५; ११; १७; १८; २०; ६१, १;
३; ६–८; ६२, ४; ११; ६३, ९;
६४, ४[२]; ६; ८; १०; १२;
६५, १; ३–५; ९; ११; ६६, ७;
८[२]; १२; ६७, ११; ६८, १; २;
१५; १८; ६९, १; ३; ५; १०;
१६; ७०, ६; १५; ७१, ११; ७२,
१; ४; ८; १३; १७; ७३, २; १०;
१४; १८; ७४, ४; ७; ७५, ५;
९; १५; ७७, ५; ६; ८; १०; ७८,
१–३; ९; १०; ७९, ४; ८०, ८;
८१, ७; ८२, १; ४[२]; ७; ९; ८३,
१; ६; ८५, १; ८; ८७, १; २; ६;
८८, ३; ४; ८९, २; ७; ९०, १;
२; ४; ९१, ३; ९२, १; ३; ७; ९;
१०; १२; ३१; ९३, १६; १७;
१९; २५–२९; ९४, ६; ९; ९५,
१; २; ८; ९६, १; ३; ५; ८;
१२; ९७, १; ४; ५; १३; ९८, ४;
१०[२]; ९९, १; २; १००, ५[२]; ८;
११; १०१, ७; ९; १४; १६; १०२,
२; ४; ६; ९; ११; २०; १०३,
९; ११; १४; **९.** १, २; ७; १०;
२, १; २[२]; ३, ८; ४, ५; १०;
५, ८; ९; ११; ६, ३; ७, ८; ८,
६; ७[२]; ९, ५; १०, ८[२]; ११, ५;
१२, ५; ९; १३, ५; १६, ३; ४;
१७, ४; १८, ४; ७; १९, १; ३;
६; २०, २; ४; ५; २१, ५; २२,
७; २३, ३; २५, २; ६; २६, २;
२७, ६; २९, ६[२]; ३०, ३; ३२,
४; ३३, ६; ३५, १; ३६, ५; ६;
३८, ४; ५; ३९, ३; ४; ४०,
२–६; ४१, ४; ५; ४३, ५; ४४,
३–५; ४५, २; ४६, ४; ४९, १;
३; ५१, १; ५२, १; ५४, २; ५७,

४; ५८, ३; ४; ५९, १; ६०, ४;
६१, १; ४; ६; ८; १०; ११;
२१; २६; २७; ६२, ४; ७; ८;
१२; २०; २१[२]; ३०; ६३, १; २;
६; १६; १८[२]; २२; २३; ६४, ६;
११[२]; १२; १७; २०; २६; २७;
२९; ६५, २; ३; ५[२]; ९; १३;
१४[२]; १७–१९; २१; २४; २८[२];
२९[४]; ३०[४]; ६६, १२; १५[२]; १८;
१९; २८; ६७, ६; १०; १४; २३;
३०; ६८, १–३; ६; ७; ९; ६९,
८; ७०, ५; ७; ९; १०; ७१, १;
४; ५; ६[२]; ७२, ५[२]; ९; ७३,
५–९; ७४, ५; ८[२]; ७५, १; ३;
७६, १; ३; ७७, २; ८०, २–४;
८१, ३; ८३, ३; ५; ८४, २; ३[२];
४; ८५, २; ७; १०[२]; ८६, १४;
१८; २२[२]; २३; २४; ४०; ४७;
८७, ४; ६; ८; ८८, ३; ५; ८९,
१; २; ९०, ४; ९३, ४; ९४, ४;
९५, १; ३; ९६, १–३; ७;
२०–२२; २४; ९७, २; ४; १३[२];
१८; २२; २८–३०; ३३; ३६[२];
३७; ३८; ४४[२]; ४५; ९९, १; ५;
८[२]; १००, २; १०१, ९; १४;
१०२, ३; १०४, १; ६; १०५, ६;
१०६, ४; ७; ९; १०७, १; ४; ५;
७; १०; १३[२]; १०८, ६; ७; १०;
१४[२]; १६; ११०, ४; ८; १११,
२; ११३, २; ३[२]; **१०.** १, १[२];
७[२]; २, ३; ४; ६; ३, ३; ७[२]; ६,
२–४; ५[२]; ६; ७, ४; ८, ३; १०,
१; ३; ७; १०; ११, ४; ६; ७; ९;
१३, १; २; १४, ४[२]; ५[२]; ८; १४;
१५, २–५; ९; ११; १६, ११;
१२; १७, ६; ८; १०; १८, ३;
६–८; १४; १९, २; ६; ८; २०,
८[२]; १०[२]; २१, १; ४[२]; २२, २; ३;
५; ६[२]; ७; २३, ३; ६; २४, ५;
२५, ११; २६, २; ३; ६; ८;
२७, ४; २८, १; २; ४; ५; १०;
२९, २–४; ७[२]; ८[२]; ३०, २; १४;
१५[२]; ३१, १; २;५; ६; ११; ३२,
८; ३३, १; ३४, ६; ३५, १; २;

६; ७; १०; १३; ३६, ५; ११;
३८, ५; ३९, १२; ४०, २; ७;
९; १२; ४२, २; ३; ४३, ४; ८;
४४, २; ३[२]; ४; ५[२]; ४५, ४;
१०[२]; ४६, ३; ४८, २; ४९, २;
१०; ५१, ५; ६; ५२, १; ५[२];
५३, १; ३; ७; ५४, १; ५५, ३[२];
६–८; ५६, २; ४; ६[२]; ७[२]; ५७,
३; ४; ५८, १; ५९, १०; ६०,
१; ७[२]; १०; ६१, १; ३–५; ८;
१०; २५; २६; ६२, ३; ६३, ५;
१०; १४; ६४, १; ५; ८; ११;
६५, २; ७; ६६, ९; ६७, ४; ६;
१०; ६८, ५[२]; ७०, २; ३; ६–८;
११[२]; ७२, ७[२]; ९; ७३, ३; ४;
५[२]; ९; ७४, ४; ६; ७५, ५[२]; ७६,
१; ४; ५[२]; ७७, ४; ८०, २; ४;
६; ८१, १; ८२, ४; ८३, ३; ५;
६[२]; ८४, ३; ८५, ५; १२; २०;
२६; २७; २९; ३७; ४३[२]; ४५;
८६, २०; २१; ८७, १; २; ८;
१८; ८८, ७; ९; १२; १७; ८९,
१; २; ७; १२; ९१, २; ४[२]; ७;
१२; ९२, ८[२]; ९३, ८; १०; ९४,
१२; १४; ९५, ११; ९६, १–३;
१०–१३; ९७, ७; ९८, २[२]; ३;
४; ९; ९९, २; ४; ५; ७; १००,
१; ३; १२; १०१, २; ३; ९–१२;
१०२, १०[२]; १०३, ५; १०५, १; ३;
४; १०६, १–४; १०; ११[२]; १०७,
१; १०८, ३; ७; ८; १०९, २;
११०, १; ३; ६; ८[२]; १११, १;
५; ७; १०; ११२, २[२]; ४; १०;
११३, १०; ११४, ४; ९; ११५,
४; ११६, १; २; ४[२]; ११८, १;
१२०, ४; ६; ७; १२२, २; १२४,
१[२]; ५; ७; ८; १२५, ६[२]; १२७,
२; ८; १२८, ३; १२९, १; १३०,
५; १३३, ६; १३४, ७; १३६, ३;
५; १३७, २[२]; ३; ४[२]; १३८, ४;
१४२, १; ६; १४३,२;४–६;१४४,
४–६; १४६, ४; १४७, ३; १४८,
१; ५; १५०, १[२]; ३; १५१, १;
१५३, ५; १५५, ३; ५; १५६,

३; ४; १५९, ५; १६०, २; १६१, २; ३; ५[२]; १६४, १; १६६, ४[४]; ५; १६७, २; ४; १६८, २; ३; १६९, १; ४; १७२, १; २; १७३, १; १७५, ३; १७८, २; १८०, १; २; १८१, १–३; १८४, १; २; १८६, १; १८९, १; १९१, १[२].
आऽअच्यं १०. १५, ६.
आऽअंजनेन १०. १८, ७.
आऽअयंनं १०. २४, ६.
आऽअयंने १०. १४२, ८.
आऽअये २. ३८, १०.
आऽअरंणे १. ११२, ६.
आऽअरंणेषु ८. ७०, ८.
आऽईत्ता ३. ३९, ३.
आऽईतासः १. १६५, १.
आऽईत्तौ १०. १७८, २.
आऽइत्यं १०. ६६, १४.
आऽईष्टौ ६. २१, ८.
आऽईयुर्षीणां १. १२४, ४.
आऽईयुर्षी ८. १०१, १६.
आऽईरिरे १. ६, ४; १४३, ४.
आऽईर्षत् १०. ८९, १४.
आऽउक्ता १. ६३, ९.
आः १०. ६१, ५.
आः १०. ८५, ७[२]; १२९, ३; १४९, २.
आऽकुरः ५. ३४, ४; ८. १३, ५.
आऽकरांमहे १०. १५६, २.
आऽकुरे ३. ५१, ३.
आऽक्वार्य्यस्य ४. २९, ५.
आर्की १. १४, ९.
आऽकूतिः १०. १२८, ४; १९१, ४.
आऽकूत्या १०. १५१, ४.
आऽकृतिः १०. ८५, ५.
आऽकृते ८. १०, १.
आके २. १, १०.
आकेऽनिपासः ४. ४५, ६.
आक्षाणे १०. २२, ११.
आऽक्षित् ३. ५५, ५.
आऽक्षितं ५. ७, ७.
आक्षिषुः १. १६३, १०.
आखंडल ८. १७, १२.
आऽखरे १०, ९४, ५.
आखुं ९. ६७, ३०.
आगः १. १७९, ५; १८५, ८; २. २७, १४; २८, ५; २९, १; ५; ४. ३, ५; १२, ४; ५. ३, ७; १२; ८५, ७; ७. ५७, ४; ८६, ४; ८७, ७; १०. १३७, १.
आऽगंताः १०. ८५, ३१.
आऽगंतायां ७. १०३, ३; ९.
आऽगतेन १०. ७१, १०.
आऽगंतौ २. ५, ६.
आऽगत्यं ३. ३५, ८; ४२, ७; ५०, १.
आऽगंधिता १. १२६, ६.
आऽगमंत् ३. ४२, ४; ५. ४२, ७; ८. १०३, ९.
आऽगमंन् ५. ५६, २; ९. ४९, २.
आऽगंमिष्ठः ३. ५८, ९; ४. ४३, २; ६. ५२, ५; ६.
आऽगंमिष्ठा ५. ७६, २.
आऽगंमिष्ठाः १०. १५, ३.
आगंसि ८. ४५, ३४.
आगांसि ७. ८८, ६.
आग्निऽवेशिं ५. ३४, ९.
आग्नींध्रात् २. ३६, ४.
आघाटिभिःऽइव १०. १४६, २.
आघृणिः १. २३, १४; १०. १७, ५.
आघृणिवसो इत्याघृणिऽवसो ८. ६०, २०.
आघृंणे १. २३, १३; ६. ५३, ९; ५५, १.
आघृणे १. १३८, ४; ३. ६२, ७; ६. ४८, १६; ५३, ३; ८; ५५, ३; ७. ४०, ६; ८. ४, १७; १८; ९. ६७, १२.
आऽघोषंते १. ८३, ६.
आऽघोषंन् ८. ६४, ४; १०. ८९, १६.
आऽघोषयंतः १०. ७६, ६; ९४, ४.
आंगिरसः ६. ७३, १; १०. ४७, ६; ६८, २; १४९, ५; १६४, ४.
आंगिरसस्यं ४. ४०, १.
आंगिरसान् ६. ३५, ५.
आंगूषः ३. ५८, ५; ५. ७४, ८.
आंगूषं १. ६१, २; ३; ६२, १; ११७, १०; ६. ३४, ५; ७. २४, ३.
आंगूषाणां ९. ९०, २.
आंगूषान् १. १३८, २.
आंगूषेणं १. १०५, १९.
आंगूषेभिः ४. २९, १.
आंगूषैः ७. ९४, ११.
आंगूष्यं १. ६२, २; ९. ९७, ८.
आऽचक्रे १. ४०, २; ८. ४५, ५.
आचक्राणः १०. ८, ९.
आऽचक्रिः ६. २४, ५.
आऽचक्रे ८. १०१, १.
आऽचखादं ६. ६१, १.
आऽचरंणेषु १. ४८, ३.
आऽचरंती १. १२३, ९; १६४, ४०; ७. ७६, ३.
आचरंती इत्याचरंती ६. ७५, ४.
आऽचरंतीः ८. ९६, १५.
आऽचिकेंतत् ७. ४२, ४.
आऽचितं १. १८२, २; १०. ८६, १८.
आऽचितां ७. ६५, १.
आऽचुच्युवीमहिं ८. ९, ९.
आछत्ऽविधानैः १०. ८५, ४.
आजः ७. ५, ६; ८. ३, १९; १०. १३८, २.
आऽजगंथं १०. ४५, २; १०८, ९.
आऽजगन्वान् ७. ७, ५.
आऽजगामं १०. २८, १; १६५, १.
आजत् १. ८३, ५; २. २४, ३; ४. ५०, ५; ८. १४, ८; १०. ६८, ५; ७.
आजत १. १६१, ६; ३. ४४, ५.
आर्जतं १. ११२, १६.
आजन् ४. १, १३.
आऽजनिष्ठाः ५. ३०, ५.
आऽजभारं ७. ३३, १०.
आजऽमीळ्हासः ४. ४४, ६.
आजयंः १. ८१, ३; ७. ३२, १७.
आऽजयंन् २. २७, १५.
आऽजरसायं १०. ८५, ४३.
आजा १. ६३, ६; १०२, ३; १०; ११६, २; १५; ७. ८३, २; ९. ६६, ८.
आऽजातः १. १७९, ४.
आऽजाता ४. ४३, ३; १०. १२९, ६.
आऽजानीः ३. १७, ३.

आजिऽकृत् ८. ४५, ७.

आऽजिगाति १. ११७, २.

आजिऽतुरं ८. ५३, ६.

आजिऽपते ८. ५४, ६.

आजिं १. १७९, ३; ४. २०, ३; २४, ८; ४१, ८; ४२, ५; ५८, १०; ५. ४१, ४; ६. २४, ६; ७५, २; ७. ९८, ४; ८. ४५, ७; ५३, ८; ९. ३२, ५; १०. १०२, १२.

आजिषु १. ८१, १; १३०, ८[२]; २. ३४, ३; ४. १७, ९; ५. ३५, ७; ७. ८३, ६; ८. ८४, ८; १०. १५६, १.

आजीन् ६. ३५, २.

आऽजुहोति ७. १, २३.

आऽजुह्वानः १. १८८, ३; ५. ३७, १; १०. ११०, ३.

आऽजुह्वानस्य १. १२७, १; ७. १६, ३.

आऽजुह्वानाः ७. २, ४.

आजेः ४. ४१, ११; १०. १०२, ५.

आऽजोहुवानाः १०. १७८, २.

आजौ १. ५१, ३; ५२, १५; ११२, १०; १७६, ५; ३. ३२, ६; ५३, २४; ४. १६, १९; ६. १९, ३; २०, १३; ८. ९६, १४; ९. ९१, १; ९७, १३; २०; १०. ६१, १; ८; ६८, २; ७५, ९; १०२, १.

आऽज्ञाता १०. ५४, ५.

आज्यं १०. ९०, ६; १२२, ७; १०३, ३.

आज्येन १०. ५३, २; ८८, ४.

आज्यैः १०. ७९, ५.

आंजन् ६. ६३, ३.

आंजनऽगंधिं १०. १४६, ६.

आणिः ५. ४३, ८.

आणिं १. ३५, ६.

आणौ १. ६३, ३.

आंडा १. १०४, ८; ८. ४०, ११.

आंडाऽइव १०. ६८, ७.

आंडानि ८. ४०, १०.

आत् १. ६, ४; १८, ८; ३२, ४[२]; ३३, १; ५१, ४; ६७, ४; ६८, २; ७१, ३; ४; ८२, १; ८३, ४; ८७, ५; ९४, १०; ११५, ४; ११६, १०; १२७, ५; १३१, ५; १४०, ५; १४१, ४–६; ८; १४४, ३; १४८, ४[२]; १६१, ४; १६३, ७; १६४, ३७; ४७; १६८, ९; २. ५, ७; १७, ४; २४, ९; ३. ९, ९; २६, ८; ३०, १२; ३१, १५; ५४, ७; ११; ४. १, १८[२]; २३, ६; २४, ४; ५[४]; ३०, ७; ३३, २; ५४, २; ५. १, ३; ७, १०; २९, ४; ३०, ८; ३२, ३; ६५, ४; ८५, ४; ६. ६७, १०; ७. १६, ११; ३३, ६; ६४, ३; ६६, ११[२]; ८. ६, ३०; १२, ८; २५; २१, १४; २६, २०; ३२, ११; ५१, ४; ८; ५५, ५; ६०, १५; ६३, ५; ७७, २; ८०, ९; ८२, ३; ९१, ५; ६; ९३, १५; १००, १; ९. १४, ३; ३२, २; ३; ४७, ३; ६२, ६; ७०, ३; ८८, २; ९७, २२; ११०, ६; १०. २७, ३; ४८, ९; ८२, १; २; ८६, १३; १८; ८८, ८[२]; ११; ९२, ३; १११, ३; ९; ११३, ५.

आऽततः ६. २, ६; १०. ५७, २; १३५, ६.

आऽततंथ ३. २२, २.

आऽततन्वान् ३. १, ५.

आऽततं १. २२, २०; १०. ५६, ६.

आऽतता १. १०५, ९.

आऽततान ७. ४७, ४; १०. ८८, ३.

आऽतनिः २. १, १०.

आऽतपः ५. ७३, ५; ८. ७३, ८.

आऽतपः १. ५५, १.

आतयः १०. ९५, ९.

आतस्थिऽवांसः ५. ४७, २.

आतस्थिऽवांसं १. ११६, ५.

आतस्थिऽवांसा २. १२, ८.

आताः ३. ४३, ६.

आतासु १. ५६, ५; ११३, १४.

आतिथिऽग्वे ८. ६८, १६; १७.

आतिथ्यं १. ७६, ३; ४. ४, १०; ५. २८, २.

आतिथ्ये ४. ३३, ७.

आऽतिष्ठंतं ३. ३८, ४.

आऽतुचिं ८. २७, २१.

आतुजी इत्याऽतुजी ७. ६६, १८.

आऽतुजे ७. ३२, ९.

आऽतुतोद १०. १६, ६.

आतुरं ८. २२, १०.

आतुरस्य ८. २०, २६; ७२, १७.

आऽतृदः ८. १, १२.

आतैः ९. ५, ५.

आत्मऽदाः १०. १२१, २.

आत्मनः १०. १६३, ५.

आत्मनि ९. ११३, १.

आत्मन्ऽवत् ९. ७४, ४.

आत्मन्ऽवतीभिः १. ११६, ३.

आत्मन्ऽवंतं १. १८२, ५.

आत्मा १. ११५, १; १६२, २०; १६४, ४; ७. ८७, २; १०१, ६; ८. ३, २४; ९. २, १०; ६, ८; ८५, ३; १०. १६, ३; ९७, ११; १०७, ७; १६८, ४.

आत्माऽइव १. ३४, ७; ७३, २.

आत्मानं १. १६३, ६; १०. ९२, १३; ९७, ४; ८.

आथर्वणः १. ११६, १२.

आथर्वणाय १. ११७, २२.

आर्दः १. १२१, ८.

आदुग्मासः १०. ७१, ७.

आर्दत् १. १२७, ६; २. १२, ४; ५. २२, ८; १०. ६८, ६.

आददाथे इत्याददाथे १. १३९, २.

आऽददानः १०. १८, ९.

आऽददानः ४. १९, ९.

आऽददिः १. १२७, ६; २. २४, १३; ८. ४६, ८.

आऽददे १. १६१, १२; ८. ४६, २१[२]; ९. ७९, ४.

आऽदधत् ९. १९, ५; ९९, ६.

आऽदधते ६. ४८, १७.

आऽदधर्षत् २. ४१, ८.

आऽदधर्षति ८. २७, ९.

आऽदधाति १०. ७९, ५.

आऽदधानः ९. ९०, १.

आऽदधुः ५. १६, ३; ८. ८४, २; १०३, १.
आऽदधे ९. ७७, ४; १०. ९७, ११.
आदने ६. ५९, ३.
आऽदभंत् ७. ५६, १५.
आऽदभुः ३. १६, २; ६. ४६, १०.
आऽदभे ८. २१, १६.
आदे १. १२६, २.
आऽदर्ता ४. २०, ६.
आऽदर्दिरः ८. १००, ४.
आऽदर्दिरासः १०. ७८, ६.
आदाम ५. ३०, १५.
आऽदार्य ४. २६, ६; ७; १०. १६६, ५.
आऽदारः १. ४६, ५.
आऽदारिणं ८. ४५, १३.
आऽदितेयं १०. ८८, ११.
आदित्य १. २४, १५; ३. ५९, २; ८. ५२, ७; १०१, ११.
आदित्यः १. २५, १२; ५०, १३; १०५, १६; १६३, ३; १९१, ९; २. २८, ४; ३. ५९, ५; ७. ८४, ४.
आदित्यऽजूतः ८. ४६, ५.
आदित्यं १. २४, १३; ४. १, २; १०. ३६, ४.
आदित्यस्य २. २८, १; ३. ५९, ३.
आदित्या ५. ६७, १.
आदित्या १. १३६, ३; ५. ६९, ४.
आदित्या ७. ८५, ४.
आदित्याः १. ४१, ५; २. २९, १; ८. १८, १२; १९; २२; ४७, ११; ६७, ७; १५; १६; २०; १०. ६६, १२.
आदित्याः २. ४१, ६; ३. ८, ८; ७. ५१, ३; ६०, ४; ८. ४७, ४; ९. ११४, ३; १०. ६५, १; ८५, १; २; १२८, ९.
आदित्याः १. १०६, २; १८८, ४; २. ३, ४; २७, ५; ६; ८; ११; १६; ६. ५१, ५; ६२, ८; ८. २७, २२; ४७, १; ६; ८३, ५; १०. ३५, १२; ६३, ७; १७.
आदित्यान् १. १४, ३; ४५, १; ९४, ३; ३. २०, ५; ४. २५, ३; ६. ५१, ४; ७. ४४, १; ८. ६७, १; १०. ३६, १; ६३, ३; ५; ६५, ९; ६६, ४; १४१, ३.
आदित्यानां २. २७, १३; ३. ५६, ४; ७. ५१, १; ८. १८, १; २; २१, १२; ४७, ५; ६७, ३; १०१, १५; १०. ३५, ९; ४८, ११; १०३, ९.
आदित्यासः १. ४१, ४; १०७, १; ८. १८, १०; ११; १८; ४७, २; ७; ६७, ५; १४; १९; २१.
आदित्यासः २. १, १३; २७, २-४; ३. ५४, १०; ५. ५१, १२; ७. ५१, २; ५२, १; ८. २७, ६; ६७, २; १०. ७७, २; १२६, ५; ७.
आदित्यासः ८. १९, ३४; १०. ६३, १३.
आदित्येन १०. ७७, ८.
आदित्येभिः १. २०, ५; ७. १०, ४; ३५, ६; ४४, ४; ८. ९, १२; ९. ६१, ७.
आदित्येभ्यः २. २७, १.
आदित्येषु ८. २७, ३.
आदित्यैः १. १०७, २; २. ३१, १; ३. ५४, २०; ४. ३४, ८; ५४, ६; ५. ५१, १०; ८. ३५, १; १३; १०. ६६, ३; ९८, १; १२५, १; १५०, १; १५७, २; ३.
आऽदिदेशति १. ४२, २; ६. ५६, १; ९. ५२, ४; १०. १३३, ४.
आऽदिशः ८. ६०, १२; ९२, ३१.
आऽदिशं ८. ९३, ११; १०. ६१, ३.
आऽदिशा ६. ४, ५.
आऽदिशे ६. ४८, १४; ५६, १; ९. २१, ५; ६.
आऽदीध्ये १०. ३४, ५.
आऽदुरे ४. ३०, २४.
आऽदुद्रुः ९. ७२, २.
आऽदृत्य १. १०३, ६; ८. ६६, २.
आऽदेदिशानः ९. ७०, ५.
आऽदेदिशानान् ६. ४४, १७.
आऽदेवं ४. १, १[२].
आऽदेवासः ७. ९२, ४.
आऽदेवीः ६. ४९, १५.
आऽदेवे २. ४, १.
आऽद्वादशं १०. ११४, ६.
आऽधवं १०. २६, ४.
आऽधवे १. १४१, ३.
आऽधानं १०. ९४, ८.
आऽधिः १०. १०९, ३.
आऽधीतं १. १७०, १.
आऽधीषमाणायाः १०. २६, ६.
आऽधून्वते ९. ७२, ८.
आऽधृषः २. १, ९.
आऽधृषे १. ३९, ४; १३६, १[२]; ५. ८, ५; ८७, २; ९. ५३, ३; १०. ४९, ४.
आऽध्यः १. १०५, ७; ८.
आऽध्ये १०. ९५, १३.
आध्रः ७. ४१, २.
आध्रस्य १. ३१, १४.
आध्राय १०. ११७, २.
आध्रेण ७. १८, १७.
आध्वं ७. ३३, १४.
आध्वर्यवं १०. ५२, २.
आन १०. ५५, ५.
आनंश ८. ६८, ८.
आनंशुः ४. २३, २; ८. २४, १७.
आनजाना १. १०८, ४.
आनजे १. १०२, १; ८. ६३, १.
आनजे १. १६१, ४; ८. ६३, २.
आनजे १. ८७, १.
आनट् १. ७१, ८; १२१, १; १६३, ७; ३. ३०, १२; ४. १, ९; १३, ४; १५, ११; ७. ९०, २; ८. ४, ६; १०. २०, ४; ७०, ९; १२२, ३.
आनट् ४. ५८, १; ६. ४९, ८; ७. ७, ७; २८, २; ८. ६, ४८; ४५, २७; १०. ८, १; २७, ७; २९, ८; ६७, ७; १०२, ११; १०४, ६; १०८, १; १११, २.
आऽनंदं ९. ११३, ६.
आऽनंदाः ९. ११३, ११.
आनं १. ५२, १५.
आऽनमं ४. ८, ३.
आनवं ८. ७४, ४.
आनवस्य ७. १८, १३.
आनवाय ६. ६१, ९.

आनवे ८. ४, १.
आनश ३. ६०, १; १०. ६२, १.
आनश ३. ६०, २; ४. ३६, ४.
आनशुः १. ५२, १४; २. २४, ६; ५. १०, ३; ६. २२, ४; ८. ३, १३; ९. १०८, ४; १०. ५३, १०; ६६, २; १४७, ३.
आनशुः १. ११०, ४; १५१, ९; १६४, २३; २. २३, २; ३. ६०, ३; ८. ३, १६; १२, १९–२१; ९. २२, ३; ५; १०. ६३, ४.
आनशे ५. ७, ८; १०. १००, २.
आनशे १. ८४, ६; ५. ८१, ५; ९. ४८, ५; १०. ९६, ७.
आनश्म १०. ३१, ३.
आनश्यां ६. २६, ७.
आऽनह्यमानः १०. १०२, ८.
आनाश ६. १६, २६.
आऽनिनाय ८. २१, ९.
आनीत् १०. १२९, २.
आनीत् १०. ३२, ८.
आऽनीतः ९. ९६, २४.
आनुषक् १. १३, ५; ५२, १४; ५८, ३; ७२, ७; २. ६, ८; ३. ११, १; ४१, २; ४. ४, १०; ७, २; ५; १२, ३; ५. ६, ६; १०; ९, १; १६, २; १८, २; २१, २; २२, २; ६. ५, ३; ४८, ४; ८. ९, १७; १२, ११; १३, ३०; २३, ६; २६, ६; २७, ७; ४४, ८; ४५, १; ५३, ६; ९. १०२, ७; १०. ४९, ५; ६, ८३, १; १७६, २.
आनुऽस्तुभस्य १०. १८१, १.
आनूकं ५. ३३, ९.
आनृचुः १. १९, ४; ५. ६, ८; ८. ५१, ४.
आनृचुः ८. ५१, १०.
आनृचे १. १६०, ४.
आनृधे १०. ७९, ७.
आऽनेता ९. १०८, १३.
आऽनोनवीति १०. ६८, १२.
आंत्राणि ४. १८, १३.
आंत्रेभ्यः १०. १६३, ३.

आपं १. १२२, ९; ४. ५१, ७; ५. ४५, ६.
आप १. ७६, १; ४. १, ९; २३, २; ४१, १; ५. ४२, ६; ७. ९९, २; १०. ३२, ८.
आपः १. ८, ७; २३, २०; २१; २३; २४, ६; ३२, २; ८; १०; ११; ३३, ११; ५७, २; ६३, ८; ६५, २; ८३, १; २; ९६, १; १००, १५; ११६, ९; १२५, ५; १५३, ४; १६१, ९; १६९, ३; १७३, ८; १७५, ६; १७६, ६; १७८, १; २; १९०, ७; २. २४, १२; ३०, १; ३५, ३; ४; १४; ३८, २; ३. १, ११; २२, ३; ३०, ९; ३३, ७; १३; ३५, ८; ३६, ६; ५१, ५; ५४, १९; ५६, ४; ७; ४. ३, १२; १७, २; ३; १८, ६–८; ३३, ७; ३८, ४; ४७, २; ५७, ३; ५. ३४, ९; ४१, ११; १२; ४५, १०; ४७, ५; ५३, १४; ५४, २; ५८, ६; ६. २४, ६; ३४, ४; ४०, २; ४८, ५; ६६, ११; ७. १८, १५; २३, ४; ३४, २; ३; २३; २५; ३५, ८; ४७, १; ४९, १; २; ८५, ३; ९०, ४; १०१, ४; १०३, २; ८. ६, ३४; १३, ८; १५, ८; ३२, २३; ३३, १; ३९, १०; ४९, ३; ५०, ३; ५४, ४; ५९, २; ६९, ११; ८९, ४; ९६, १; १०२, १४; ९. २, ४; ६, ४; २४, २; ६६, १३; ८२, ३; ५; ८८, ७; ११३, ८; १०. २, ७; ४, ५; ९, १; ३; ४; १२, ४; १७, १०; २७, २०; ३०, ६; ८; १२; १३; १५; ३७, २; ६; ४३, ७; ४६, ९; ६४, ९; ६५, १३; ६६, ९; १०; ७८, ५; ८२, ५; ८५, ४७; ८८, २; ८; १८; ८९, १३; ९१, ६; ९५, १३; ९८, ६; १०४, ८; १०९, १; १११, ८[२]; १२१, ७; ८; १३७, ६[२]; १३९, ४.
आपः १. २३, २२; ६. ५०, ७; ७. ४७, २; ८. ७४, १५; १०. ३०, ११; ७५, १.

आपःऽइव ३. ५, ८; ५. ६०, ३; ७. १०४, ८; ८. ९४, ७.
आपंत् ९. ९२, १.
आपत् ८. ७०, ७; १०. १०६, ७.
आपतुः १०. ११४, १.
आऽपंथयः ५. ५२, १०.
आऽपथ्यः १. ६४, ११.
आपन् ६. १, ४.
आऽपनीफनत् ४. ४०, ४.
आऽपप्राथ १०. १३४, १.
आपप्रिऽवांसं १. १४६, १.
आपप्रिऽवान् १. ७३, ८; १०. १३९, २.
आऽपप्रुषी ४. ५२, ६; ६. ६१, ११.
आपयः १. ११०, २; २. २९, ४; ३४, १०; ५. ५३, २.
आपयायां ३. २३, ४.
आपये १. २६, ३; २. ३८, ११.
आपानं २. ३४, ७.
आपानासः ९. १०, ५.
आपांतऽमन्युः १०. ८९, ५.
आपिः १. २६, ३; ३१, १६; ३. ५१, ६; ९; ४. १७, १७; २५, ६; ६. २१, ८; ४४, १०; ४५, १७; ७. ८८, ६; ८. ३, १; ४५, १८; १०. ११७, ७.
आपिऽस्वं ८. २०, २२; २१, १३.
आऽपिस्वे ८. ४, ३.
आऽपिप्यानं ४. २७, ५.
आऽपिब्दमानः १०. १०१, ११.
आपिं ८. ६०, १०; १०. ७, ३.
आपिरे ९. १०८, ४.
आपिषु २. २९, ४.
आपी इति ४. ४१, २; १०. १०६, ४.
आऽपीतासः ८. ९, १९.
आपीन् ७. ३१, १२.
आपुः १. २४, ६; ३३, १०; १००, १५; १६७, ९; १७९, २.
आपुः १०. ५४, ३.
आऽपूर्णः ३. ३२, १५; ९. ७४, २.
आऽपृक् १०. ८९, १४.
आऽपृचः ८. ४०, ९.
आऽपृचे ५. ५०, २.

आऽपृच्छ्यः १. ६०, २.
आऽपृच्छ्यं १. ६४, १३; ९. १०७,५.
आऽपृणन् ४. ५३, २.
आऽपृणतः ७. ७५, ३.
आपेः २. २७, १७; २८, ११; २९, ७; ४. ३, १३; १०. ८३, ६.
आप्तः १. ३०, १४.
आप्ताः ९. ११३, ११.
आप्त्यः १. १०५, ९; ५. ४१, ९; १०. ८, ८.
आप्त्यं १०. १२०, ६.
आप्त्यानां १०. १२०, ६.
आप्त्याय ८. ४७, १४.
आप्त्ये ८. १२, १६; ४७, १३; १५; १७.
आप्नानं १०. ११४, ७.
आप्यं १. ३६, १२; १०५, १३; ३. २, ६; ७. १५, १; ३२, १९; ८२, ८; ८३, १; ८. १०, ३; २७, १०; ७३, ६; ९७, ७; ९. ६२, १०; ११०, ६; १०. ६३, १; १४२, १.
आऽप्यायमानः १. ९१, १८.
आऽप्यायमानाः १०. १८, २.
आप्येन २. २९, ३.
आऽप्रस्थं १. १३२, २.
आऽप्रुषायन् १०. ६८, ४.
आऽबभूथ १०. ८४, ५.
आऽबभूव १०. १२९, ६; ७.
आऽबाधः ८. २३, ३.
आऽभगः १. १३६, ४²; १०. ४४, ९.
आऽभगं ८. ५३, ६.
आभरत्ऽवसुः ५. ७९, ३.
आऽभासि १. ४९, ४.
आभिः ६. २५, २²; ८. २३, २३.
आभिः ४. १०, ४; १७, १८; ५. ३८, ५; ८३, १; ६. १८, १; २२, १; २४, ६; ४९, १०; ५२, १; ६३, ६; १०. ४९, ३.
आभिः ५. ३२, १०; ६. २२, ११; ७. ९१, ६; १०. ७३, ५.
आभु १०. १२९, ३.
आभुं १०. २७, १; ४.
आऽभुवः १. ६४, १; ६; ९. ६५, २७.
आऽभुवत् ८. १०२, ८.
आऽभुवे १. १३३, ७²; १५१, ४.
आऽभूत्या १०. ८४, ६.
आऽभूभिः १. ५१, ९; ५. ३५, ३.
आऽभूपति १. १३६, ५.
आऽभूपतः १०. १६०, ५.
आऽभूपती: १. ४३, ९.
आभूषु १. ५६, ३.
आऽभूषेण्यं ५. ५५, ४.
आऽभृतः २. ३६, ५; ४. ५८, ११.
आऽभृतं १. २५, १७; १६१, १०; ६. ४७, २७; ९. ६६, ३०.
आऽभृता ६. १६, ४८; १०. १७०,४.
आऽभृत्य १०. ७१, ३.
आऽभोगं ७. ९४, १२.
आऽभोगयं १. ११०, २.
आऽभोगये १. ११३, ५.
आभ्यः २. ३२, २.
आभ्यः ६. ३०, ३; १०. १७, १०.
आभ्यां २. ४०, २.
आभ्यां ४. ३२, २२.
आमऽअदः १०. ८७, ७.
आमः ९. ८३, १.
आममत् ९. ११४, ४; १०. ५९, ८.
आमयत् १०. ८६, २३.
आमयति १०. ९७, ९.
आऽमरीता ४. २०, ७.
आमस्य १. १६२, १०.
आमा ३. ३०, १४; ४. ३, ९.
आमायां १. १८०, ३.
आमासु १. ६२, ९; २. ३५, ६; ४०, २; ६. १७, ६; ७२, ४; ८. ८९, ७.
आमित्रः ६. २८, ३.
आऽमिनाना १. ९२, १०.
आमिनाने इत्याऽमिनाने १. ११३, २.
आमिश्लऽतमः ६. २९, ४.
आमिमिव ६. ४६, १४; १०. ९४, ३.
आऽमुरः ४. ३१, ९; ८. २४, ५; ३९, २; ९. ६१, २४.
आऽमुरि ८. ९७, १०.
आऽमुष्य ३. ४८, ४; ८. ४, ४.
आऽमेन्यस्य ५. ४८, १.
आमेन्याने इत्याऽमेन्याने १. ९६, ५.
आऽयजते ३. ४, २.
आऽयजसे १. ९४, २.
आऽयजाते ७. ६०, ११.
आऽयजि ८. २३, १७.
आऽयजिष्ठः २. ९, ६; १०. २, १.
आयजी इत्याऽयजी १. २८, ७.
आऽयज्यवः ९. ९७, २६.
आऽयत् ३. ५५, ८.
आयत १. ८०, १२; १०. ७२, ६.
आऽयतः १०. १३०, १.
आऽयतं ८. ९२, ७.
आऽयता ५. ४४, ९.
आऽयतां १. १६९, ७.
आऽयतिः १. १३९, ९.
आऽयती १. ११९, २; ७. ८१, १; ८. १०१, १३; ९. ६९, १; १०. १२७, १; ३.
आऽयतीः १०. ३०, १३.
आऽयतीनां १. ११३, ८; १२४, २.
आऽयतीं ३. ६१, ६; ५. १, १.
आऽयते २. १३, ४.
आऽयत्याः ५. ४५, १.
आयन् २. २४, ६; ३. ३३, ७; ३६, ६; ७. १०३, २; १०. ६९, ९; १२१, ७; १५७, ४.
आयन् १. ३३, ४; ६; १६३, ९; ३. ३१, ४; ४. २६, २; ३३, २; ६. ७, ४; २७, ६; ७. ५, ३; ५६, १२; ९. ९४, ४; ९७, २२; १०. ६, ७; २७, ८; १५²; १८; २३; २८, ८²; ४४, ६; ७१, ३; ९८, ९; १११, १०; १३९, ४.
आऽयन् ९. ९७, ५; १०. ८५, १९; ८८, १९; १२४, ४.
आऽयंतं १. १२५, २.
आऽयंतारं ८. ३२, १४.
आऽयंति ५. ६, २.
आयं १. १२५, ३; १०. १०८, १०.
आयुं १. ११, ६; ५. ३०, २; १०. ५१, ४; ६; ९५, ५.
आऽयुय १. १६८, ६; ५. ६१, १.
आऽययुः ५. ५३, ३; १०. ६३, ५; १३०, १.

आयर्वः १. ६०, ३; ११७, २५; १३०, ६; १३१, २[२]; १३९, ३[२]; २. ३१, ७; ४. ७, ४; ५. ४३, १४; ६. १४, ३; ८. ३, ७; ८; १६; १२, १३; ९. १०, ६; १५, ७; २३, २; ४; ६२, २०; ६३, १७; ६४, १७; २३; ८६, २५; १०७, १४; १७; १०. ७, ५; ४६, ८; ७४, ४.

आयंवसस्य १. १२२, १५.

आयवे १. ३१, २; ११; १४०, ८; २. २, ८; ३. ६०, ७; ५. ७, ६; ७. ४, ३; ८. १५, ५; ९. ६७, ८; १०. ४९, ५.

आयसः १. ५६, ३; ८०, १२; ८. ९६, ३; १०. ९६, ३; ४; ८.

आयसं १. ५२, ८; ८१, ४; १२१, ९; १०. ४८, ३; ११३, ५.

आयसी ७. १५, १४; ९५, १.

आयसीः २. २०, ८; ४. २७, १; १०. १०१, ८.

आयसीभिः १. ५८, ८; ७. ३, ७.

आयसीं १. ११६, १५.

आयसीं ८. २९, ३; १००, ८.

आऽयाने ८. २२, १८.

आयुः १. १०, ११; २४, ११; ३४, ११; ३७, १५; ४४, ६; ५३, ११; ६६, १; ७३, ५; ८९, २; ८; ९; ९२, १०; ९३, ३; ९४, १६; ९६, ८; ११३, १६; १७; ११६, १०; १९; २५; १२५, १; ६; १२७, ५; १३२, ५; १५७, ४; २. ३२, १; ३८, ५; ३. १, ५; ७, १; ४९, २; ५३, ७; १६; ६२, १५; ४. १२, ६; ६. १६, २७; ५२, १५; ७. २३, २; ७७, ५; ८०, २; ९०, ६; १०३, १०; १०४, १५; ८. १८, १८; २२; ३१, ८; ४४, ३०; ४८, ४; १०; ११; ५४, ७; ५९, ७; ७९, ६; ९. ८०, २; ९३, ५; ९६, १४; १०. १४, १४; १६, ५; १७, ४; १८, ६[२]; २७, ७; ३६, १४; ४५, ८; ५१, ७; ८; ५३, ३; ५९, १; ५; ६२, ११; ८५, १९; ४२; ९५, १०; १०७, २; १४४, ५; १६१, ५; १७०, १.

आयुः १. १६२, १; ५. ४१, २; ९. ६७, ८.

आयुधं २. १५, ४; ३. ४४, ४; ५. ६३, ४; ६. ७५, ८; ८. ६, ३; २९, ५; ९६, ९.

आयुधा १. ३९, २; २. १६, ६; ५. २, ३; ५७, ६; ८. २०, १२; ९. ३५, ४; ५७, २; ६१, ३०; ७६, २; ९०, १; १०. ८४, १; १०१, २; १०८, ५; ११३, ३; १२०, ५.

आयुधानि १. ६१, १३; ४. १६, १४; ५. ३०, ९; ६. ४४, २२; ९. ९६, १२; १९; १०. ८, ७; ८; १०३, १०; १२३, ७.

आयुधानिऽइव १. ९२, १.

आयुधेभिः ७. २१, ४.

आयुधैः २. ३०, ९; ७. ५६, १३; ५७, ३.

आयुनि ३. ३, ७; ९. १००, १; १०. ५, ७.

आयुऽभिः ५. ६०, ८; ९. ५७, ३; ६२, १३; ६६, २३.

आयुं १. ३१, ११; ५३, १०; ६. ११, ४; १८, १३; ८. ५३, २; १०. २०, ७.

आऽयुयुत्रे ५. ५८, ७; १०. ४४, ७.

आऽयुयुवे १. १३८, १[२].

आयुर्वः २. ५, ५.

आयुषः १०. १००, ५.

आयुषक् ९. २५, ५; ६३, २२.

आयुषा १. २३, २४; ११९, ६; ७. १, २४; १०. ८५, ३९.

आयुषि ४. ४, ७; ५८, ११.

आयुषु १. ५८, ३; १३५, २; ३. ५९, ९; ८. ३९, १०; ९. १६, ८; १९, ३.

आयूंषि २. २५, १२; २७, १०; ४१, १७; ३. १७, ३; ४. ३९, ६; ८. ४८, ७; ९. ६६, १९; १०. १८, ५; १८६, १.

आऽयूर्य २. ३७, ३.

आऽयेजे १. ११४, २; १०. ६३, ७.

आऽयेमिरे ३. ६, ८.

आऽयै २. १८, ३.

आयोः १. ९६, २; १०४, ४; १२२, ४; १४७, १; १७४, ६; १७८, १; २. ४, २; १४, ७; २०, ४; ३२, २; ३. ५४, २; ४. २, १२; १८; ६, ११; २३, ८; ३८, ४; ५. ४१, १९; ४३, १४; ४९, १; २; ६. ६७, ६; १०. ५, ६; १०५, ४; ९.

आऽयोयुवानः ४. १, ११.

आयौ १. ११४, ८; ८. ५२, १.

आर ३. ३०, १०.

आरंगराऽइव १०. १०६, १०.

आरण्यान् १०. ९०, ८.

आरत् ४. ५८, १.

आरत १. ४, ५; ३९, ५; ५४, १.

आरथुः १०. ४०, ७.

आरन् १. ४९, ३; १०. १३२, ३.

आऽरभे ५. ३४, ५; ९. ७३, ३; १०. ६२, ९.

आऽरभमाणाः १०. १२५, ८.

आऽरभे १. २४, ५; ३४, २; १८२, ७; ९. ७३, १.

आऽरभ्य १. ५७, ४.

आऽरंभणं १०. ८१, २.

आरया ६. ५३, ५; ६.

आरात् १. १२९, ९; १६३, ६; १६४, ४३; ३. ५४, ९; ५. २, ३; ६. ४७, १३; ५६, ५; ७. ५८, ६; ८. ३२, ६; १०. २७, १९; २८, ९; ४२, ६; ७; ७७, ६.

आरात्तात् १. १६७, ९; ७. ३२, १; ८. २२, १६.

आरां ६. ५३, ८.

आरितः १. १०१, ४; २. २१, ३; ८. ३३, ५; १०. १११, १०.

आऽरिशामहे १. १८७, ८.

आरीः १. ७७, ३; ९६, ३.

आरुः ३. ७, १.

आरुः ३. १, ४.

आऽरुजः ३. ४५, २.

आरुजत्नुऽभिः १. ६, ५.

आऽरुजंतः १०. ८४, १.

आऽरुजं ८. ४५, १३.

आऽरुजासि १०. ४४, ९.

आऽरुजें ४. ३१, २.

आरुंणीपु १. ६४, ७.

आऽरुंधानः ४. ३८, ४.

आऽरुरुक्षतः ८. १४, १४.

आरुपी १०. १५५, २.

आऽरुहं १०. ४४, ६.

आरे १. ७४, १; ११४, ४; १०; १७१, ४; १७२, २[२]; १९१, १०–१३; २. २८, ६; २९, १; ५[२]; ३. ८, २; ३९, ७; ८; ४१, ८; ४. ११, ६[२]; ५. ४५, ५; ५०, ३; ६. ४७, ३; ७४, २; ७. २२, ६; २५, २; ३२, १; ५६, १७; ८. २, २०; २६; १८, १६; ४७, १३; ६१, १६[२]; ९. ६६, १९; ८१, ३; १०. ३५, ४; ६३, १२; १०२, १०; ११२, ९; १४२, १; १६४, ३.

आरेऽअंघाः ६. १, १२.

आरेऽअघां ६. ५६, ६.

आरेऽअंवद्यः १०. ९९, ५.

आऽरेळ्हि १०. १६२, ४.

आरोकाःऽइव ८. ४३, ३.

आऽरोधनं ४. ८, २; ४.

आऽरोधनानि ४. ७, ८.

आऽरोधने १. १०५, ११.

आऽरोहन् १. ५०, ११.

आऽरोहतं २. १२, १२; १०. ३७, ८.

आऽरोहयति ४. १३, २.

आर्क्षः ८. ७४, ४.

आर्क्षे ८. ६८, १६; ७४, १३.

आर्चत् १. १२०, ३; ५. ३३, ९.

आर्चत्ऽकस्य १. ११६, २२.

आर्चन् १. ५२, १५; ५. २९, २; ४५, ७.

आर्जीकात् ९. ११३, २.

आर्जीकीये १०. ७५, ५.

आर्जीकीये ८. ६४, ११.

आर्जीके ८. ७, २९.

आर्जीकेषु ९. ६५, २३.

आर्जुनेयं १. ११२, २३; ४. २६, १; ८. १, ११.

आर्जुनेयाय ७. १९, २.

आर्त ४. १, १२; ७. ३४, ७.

आर्तनासु १. १२७, ६.

आर्ली इति ६. ७५, ४.

आर्ली इवेत्यार्लीऽइव १०. १६६, ३.

आर्त्विज्या १. ९४, ६.

आर्दन् ४. १७, २.

आर्दयः ६. १७, १२.

आर्दयत् १०. १०४, १०.

आर्द्रस्य १. ११६, ४.

आर्द्रात् २. १३, ६.

आर्पिता १. १६४, १४.

आर्यः ५. ३४, ६; ८. ५१, ९; १०. ३८, ३; १३८, ३.

आर्यंति ८. १६, ६; १०. ४८, ३.

आर्यं १. १०३, ३; १३०, ८; १५६, ५; ३. ३४, ९; ९. ६३, ५; १०. ४३, ४; ४९, ३; ८३, १; ८६, १९.

आर्यस्य ७. १८, ७; ८. १०३, १; १०. १०२, ३.

आर्या ४. ३०, १८; ६. ३३, ३; ६०, ६; ९. ६३, १४; १०. ६५, ११; ६९, ६.

आर्याः ७. ३३, ७; १०. ११, ४.

आर्याणि ६. २२, १०; ७. ८३, १.

आर्यात् ८. २४, २७.

आर्यान् १. ५१, ८.

आर्याय १. ५९, २; ११७, २१; २. ११, १८; ४. २६, २; ६. १८, ३; २५, २; ७. ५, ६.

आर्येण २. ११, १९.

आर्येयं ९. ९७, ५१.

आर्ष्टिषेणः १०. ९८, ५; ८.

आर्ष्टिषेणेन १०. ९८, ६.

आलेऽअक्ता ६. ७५, १५.

आऽलब्धं १०. ८७, ७.

आऽलेभानात् १०. ८७, ७.

आव ८. ७, १८.

आव २. ११, ११; १०. ८०, ३.

आवः १. ३३, १४; १५; ११३, ९; १७६, ५; ३. ५०, २; ५. ७७, २; ६. २६, ४; ८. ३, १२; ४९, ९; १०. १०५, ११.

आवः १. ४, ८; ३३, ७; १४; ११३, १३; १५७, १; १७६, ५; २. १५, ९; ४. ३०, ६; ५२, ६; ६. २६, ५; ७. १९, २; ३[२]; ७५, १[२]; ८. ९, १६; ६३, ८; १०. ५४, १; १७१, १.

आवत् १. ८५, ७; ६. २०, ३; ७. १८, १९; ८. ९६, १३.

आवत् १. ३६, १७; ६१, १५; १३०, ८; ३. ३२, १२; ३४, ९; ४८, १; ४. १६, ७; ६. २०, ६; ७. ३३, ३; ८४, ५; ९. ९२, ५; १०. १०२, ७; १०८, २; १३०, ४; १५०, ५.

आवत १. ६४, १३; १६६, ८; १३.

आवतं १. ४७, ५; ११२, ५; ७; ९–१२; १३[२]; १४[२]; १५; २१; २३[२]; ७. ८३, ६; ८. ५, २५; ८, २०; २१.

आवतं १. ११६, २१; ७. ८३, ४; १०. १३१, ४.

आवतां १०. ११३, १.

आवतुः १. १६१, १०.

आवथुः १०. १३१, ५.

आऽवदन् १. ११, ६; २. ४३, ३.

आवन् ४. ४४, ६.

आवन् ३. ३०, १०; ८. ७, २४; ५४, १.

आवं ४. २६, ३.

आवं १०. ४९, ३.

आवयः ८. ४५, ३८.

आवयत् १०. ११३, ८.

आऽवयाः १. १६२, ५.

आऽवरः ८. १३, २१; १९, ३०.

आऽवरत् १. १४३, ६.

आवरित्यावः १०. ६७, ४.

आवरित्यावः १. ९२, ४; ११३, ४; १४; ३. ५, १; ५. ४५, १; ६. ४४, ८; ७. ७९, १; ९५, ६; ९. ९७, ३८.

आऽवर्जते १. ३३, १.

आऽवर्तनं १०. १९, ४; ५.

आऽवर्तयति ८. ६९, १७.

आऽवर्वृततीः १०. ३०, १०.

आऽववर्तत् २. ३४, १४; ६. ६८, १; ७. ८५, ४.

आऽववर्तति ५. ७३, ७.

आऽवहन्ती १. ४८, ९; ११३, १५; ४. १४, ३.

आऽवहन्ती ५. ८०, १.

आविः १. ३१, ३; ८६, ९; ११६, १२; १२३, ६; १०; ११; १२४, ४; १३१, ३; १४३, २; १४६, ४; २. १५, ७; २३, १४; ३. ३४, ३; ५५, १५; ४. १, १६; ३, ११; ४, ५; १६, ८; ५. १, ९; २, ९; ८३, ३; ६. १७, ३; ४८, १५; ६४, २; ७. ५८, ५; ७६, १; १०३, ८; ८. ८, २३; १४, ८; ४७, १३; ९. ३, ५; ७९, ५; ९५, २; १०. २७, २४; ४८, १०; ५४, ५; ६८, ६; ७१, १; ८८, २; ९६, ११; १०७, १.

आविःऽऋजीकः ४. ३८, ४.

आविःऽकृण्वती ७. ८०, १.

आविःऽकृण्वानः ४. १७, ३.

आविःऽकृण्वाना ५. ८०, ४; ७. ७५, १.

आविःऽत्यः १. ९५, ५.

आविःऽत्यं १०. १००, ७.

आविथ १. १३१, ५[२]; २. १३, ९; ८. ३, ९; १२; १२, २; ६८, १०; ८०, २; ९. ६१, २२; १०. १२०, ७.

आविथ १. ५१, ५; ६; ५३, १०; ५४, ६; ८. ३६, ७; ३७, १; ६; ४६, ११.

आऽविदे १०. ११३, ३.

आऽविद्वान् ४. १९, १०.

आऽविवाय १०. १०७, ५.

आऽविवासतः ७. ९४, ११.

आऽविवासतां ७. १०४, २१.

आऽविवासति १. १२, ९; ८४, ९; २. २६, ३; ६. ६०, ११; ८. १९, १३; १०. ९३, २.

आऽविवासन् १. १५२, ६; ७. ७२, ३; ९. ३९, ५.

आऽविवासंतः ५. ४५, ३; ४.

आऽविवासंती ५. ४७, १.

आऽविवाससि १. ३१, ५.

आऽविवासात् ७. २०, ६; १००, १.

आऽविवासान् २. ११, १६.

आऽविविद्रे ३. ५४, ४.

आऽविवेश ६. ७४, २; ८. ४८, १२; १०. १६, ६.

आऽविशन् ५. २५, ४; ७. ५५, १; ८. १५, १३; ९. २५, ४; २८, २; ५६, २; ६०, ३; ६२, १९; ८६, १९; २३.

आऽविश २. २४, ६.

आविंपुः ४. ३६, ६.

आविपुः १. ११, ५.

आऽविष्टितः १०. ५१, १.

आवीत् ७. २०, २; ९. ९७, ३९.

आऽवृणानः ४. १, २०.

आऽवृणीमहे ६. १५, ९; ८. ८३, ४.

आऽवृतः १. ८७, ४; ८. २६, १३.

आऽवृतः १०. १३०, ७.

आऽवृतं १. ५१, २; १६४, १४; ३. ३, ५; ६. ४७, २७; ८. ८८, २; ९. ८६, २७.

आऽवृते २. ३६, ६; ५. ४६, १.

आऽवृता ९. ७४, २.

आऽवृतासः १. ५५, ८.

आऽवृते ३. ४२, ३.

आऽवृत्य १. ५६, १.

आऽवृत्वत् ८. ४५, ३६.

आऽवेशयंती १०. १२५, ३.

आव्यं १. १६६, १३.

आश १. १६२, ९; ३. ३६, ८.

आश ८. ४७, ६.

आशत १. ८, ६; ८७, ५; १०. ९२, ३.

आशतः १. २०, २; ८५, २; २. २१, ५; ३. ४५, ३; ७. ६६, ११; ८. ४३, १७; ५९, २; ६९, १८; ९७, ९; ९. ६, ४; १८, ३; २१, ४; २२, ६; २४, २; ६७, ७; ६९, ७; ७३, ९; ८३, १; ४; १०. ९२, ७; ९४, २.

आशतुः ८. २५, ८.

आऽशयानं १. १२१, ११; २. ११, ९; ४. १७, ७; १९, ३; ५. ३०, ६.

आऽशये ८. ४१, ७; १०. १६२, १.

आशवः १. ५, ७; ११८, ४; १३५, ६; १४०, ४; २. ३१, २; ५. ६, १; ८. १, १५; १९, ६; ४६, २३; ४९, ८; ७४, १४; ९. १३, ६; १७, १; २२, १; २३, १; ६२, १; ६३, ४; २६; ६४, ४; १६; ६७, ७; ६९, ६; ७; ८३, २; ८६, १; २; १०. ७८, ५; ९४, १; ८; ११९, ३.

आशवे १. ४, ७.

आऽशसः ५. ३२, ११; ५६, २; ८. २४, ११; ६६, १२; ९२, १३; ९. १, ५.

आऽशसनं १०. ८५, ३५.

आऽशसा ४. ५, ११; ८. ७३, ९; ७८, १०; १०. १६४, ३.

आशाः १. ३९, ३; १६२, ७; ४. ३७, ७; ५. १०, ६; १०. १७, ५; ७२, ३; ४.

आशाते इति ५. ६६, २.

आशाते इति १. २५, ६; १३६, ३; १४४, ६; ५. ६८, ४; ५; ८. ३१, ६.

आशाथे इति १. २, ८; १५, ६; १५१, ८; ९; ५. ६७, १.

आशाभ्यः २. ४१, १२.

आशितं १०. ३७, ११; ११७, १; ७.

आशिताः १०. ९४, १०.

आशिनेभ्यः १. २७, १३.

आऽशिरं १. १३४, ६[२]; ३. ५३, १४; ८. २, १०; ११; ६, १९; ३१, २; ६९, ६; ९. ६४, १४; ७०, १; ७५, ५; ८६, २१; १०. ४९, १०; ६७, ६.

आऽशिरा ८. ३१, ५.

आऽशिषः १. १७९, ६; ३. ४३, २; ७. १७, ५; ८. ४४, २३; ५४, ७.

आऽशिषं ८. ९३, १८; १०. ६७, ११.

आऽशिषा १०. ८१, १.

आशिष्ठाः २. २४, १३.

आऽशीः १०. १२८, ३.

आशीःऽवंतः १. २३, १.

आशीःऽवान् ८. ९५, ७.

आऽशीर्तः ८. २, ९.

आशु १. ८४, १८.

आशुऽअंश्वाः ५. ५८, १.

आशुऽअश्व्यं ५. ६, १०; ८. ६, २४; ३१, १८.

आशुः ४. ११, ४; २२, ८; ७. १८, ९; ६६, १४; ९. ३९, १; ५६, १; ६४, २०; १०. १०३, १.

आशुः ४. ३३, ४.

आशुऽपत्वा ४. २६, ४.

आशुऽभिः १. ३७, १४; २. १६, ३; ३४, ३; ३८, ३; ५. ५५, १; ६१, ११; ८. ५, ७; १३, ११; ४९, ७; ६५, १; ९. १५, १; १०. ४९, ७.

आशुं १. ४, ७; ६०, ५; ९१, २०; ११७, ९; १३५, ५; २. ३२, ३; ३. ९, ८; ४. १, ३; ७, ४; ११; ३८, २; ३९, १; ४३, २; ५. ४४, १; ८. ९९, ७; ९. ६२, १८; १०. १०७, १०; १७८, १.

आशुंऽइंव १०. १५६, १.

आशुऽया ४. ४, २; ६. ४६, १४.

आऽशुशुक्षणिः २. १, १.

आशुषाणः ५. ३६, ४.

आशुषाणाः १. १४७, १; २. १९, ७; ४. १, १३; २, १४; १६.

आशुषाणासः ४. २४, ४; ७. ९३, ८.

आशुषु ८. ३४, १८.

आशुहेमंऽभिः १. ११६, २.

आशुऽहेमा २. १, ५; ३१, ६; ३५, १; ७. ४७, २.

आशुऽहेषंसा ८. १०, २.

आशू इति ३. ३५, ४.

आशून् ४. २९, ४; ६. ६०, १२.

आशूनूऽइंव १०. ६८, २.

आऽशृण्वतीः ५. ४५, १०.

आऽशृण्वते ४. ३, २.

आऽशृण्वंति १. १९०, १.

आशोः ४. ३८, ९.

आश्मां १०. ९५, १६.

आऽश्रवयति ५. ८२, ९.

आश्रवयंतःऽइव १. १३९, ३.

आश्रुत्ऽकर्ण १. १०, ९.

आश्वऽघ्नस्यं १०. ६१, २१.

आश्वंपःऽतरेभ्यः १०. ७६, ५.

आश्वऽमेधस्यं ८. ६८, १५.

आश्वऽमेधे ८. ६८, १६.

आश्वंश्वऽतमाः ५. ४१, ४.

आश्विनीः ९. ८६, ४.

आष्टं १. १२१, ६.

आष्ट्र्यां १०. १६५, ३.

आसं ५. २, ५; ७. १, २; १०४, १४; ८. २०, १५; १०. २७, ११.

आस ४. २७, २; ३५, ४; ५६, ३; ५. ४४, २; ५३, १; ६. ४७, २; ७. ३२, १०; ८६, ४; १०. ३१, ७; ६१, १८; ८३, २; १२०, १; १२४, ६; १२९, २.

आसः ७. ९९, ७.

आसक्तिः १०. ८५, २८.

आऽसंगः ८. १, ३३.

आऽसंगस्यं ८. १, ३२.

आसत १०. ९५, ७.

आसतुः १. १६१, १२.

आसंते १. १९, ६; १६८, ३; ७. ३२, २; ९. १५, २; २५, ४; ११३, ११; १०. १७, ४; ६३, १.

आसते १. ३६, ७; ४८, ६; १०५, ११; १६४, ३९; २. १३, ४; ३. २, ६; ९, ३; ६. ४७, १९; ८. ८, ८; ३३, १; ९. १०, ७; ७३, ३; ८६, १; ३९; १०. २१, ३; २५, २; ३८, ५; ४०, ७; ६५, ७; ९४, ९; १०९, ७; ११४, २; १३०, १; १५१, ४; १५३, १; १५४, १; १७९, २.

आऽसस्रिं ३. ३०, १८.

आसथुः १०. ३९, ५.

आऽसदं ३. ६२, १३; ४. ९, १; ८. १, ८; ९. ३, १; ८, ३; २५, ६; ३०, ४; ६२, १६; ६४, २२; ७१, १; ६; ८२, १; १०१, १४; १५.

आऽसदे १. १३, ७; ३. ४१, ९; ५. २६, ८; ४६, ५; ८. ६०, १.

आऽसद्य १. १०९, ५; २. ३६, २; ६. ५२, १३; ६८, ११; १०. १७, ८.

आसंन् १. १०९, ७; १७९, २; ३. ३२, ४; ५. ३०, १०; ७. ९१, १.

आसन् ३. २६, ७; ५. १८, ४; ६. ७, १; ८. ९६, ३; १०. ७३, ३; ८७, २; ९८, २; ३.

आसन् १. १६४, ४३; ५०; १७१, ४; ४. ४२, ८; ५. ५२, १२; ७. २९, ४; ३३, ६; ७६, ३; ४; १०. २७, ४; १७; ८५, ८; ९०, १५; १६; १२९, ५[२].

आसनि १. ७५, १; ४. ४०, ४; ५. ६, ९; ८. १२, १३; ३९, ३; ९. ६९, २; १०. ५३, ११.

आसन्ऽइंषून् १. ८४, १६.

आसऽभिः १. ३४, १०; १६६, ११; ४. ४५, ३; ९. ९९, ३; १०. ७६, ७; ९४, २.

आसं १०. २७, ४.

आसया १. २०, १; १२७, ८.

आससे ८. ८०, ५.

आऽसस्त्राणासंः ६. ३७, ३.

आसा १. ७६, ४; १२९, ५; १४०, २; १५२, ६; १६८, २; २. १, १४; ४. ५, १०; ५. १७, २; ५; २३, १; ६. ३, ४; ११, २; १६, ९; ३२, १; ७. १६, ९; ८. ६, २०; १९, २४; १०. १, ३; २०, ३; ४०, ६; ६७, १०; ११५, ३.

आसात् १. २७, ३; ४. २०, १.

आसाते इति २. ४१, ५.

आसांथे इति ५. ६२, ५.

आसाथे इति १. १८२, ३.

आसानः ६. १०, ६.

आसानेभिः ६. ५१, १२.

आसां १. १२४, ९; १०. ९२, १४.

आसां १. ६८, ४; ८८, ६; १३३, ३; २. ३०, १; ३. ३१, २०; ३४, ५; ५६, ४; ४. ५१, ६; ५८, ५; ५. ४४, ९; ११; ४५, ८; ६. २८, ३; ७. ३४, १०; ८. ७०, १२; ९. ८७, ३; १०. २२, १२; ६८, ७; ७५, ४; १०३, ८; १११, ८[२]; १०; १३९, ४; ६.

आऽसाव ८. १०३, १०.

आऽसिंचे २. ३७, १; ७. १६, ११.

आऽसिंचंतीः ५. ८५, ६.

आऽसिंचाः १०. ३०, ५.

आसिंथ ६. ४५, ११; १७.

आऽसिस्विदाना १०. १०६, १०.

आसीः १०. ९५, ५.

आसीत् १. ३२, ११; ५. ३०, १५; १०. १७, २; ७१, १; ८८, ४; १२१, ८; १२९, ३; ४; १८१, २.

आसीत् १. ३२, ९; १६३, ९; १६५, ६; ४. १८, १२; ७. १८, ६; ८. ५८, १; १०. ३३, १; ३४, २; ५१, १; ८१, २^{२}; ८५, ६–८; १०^{२}; १५; ९०, ६; १२; १४; १०२, ६; १०८, १; १०९, २; १२१, १; १२९, १^{४}; २^{२}; ३; १३०, ३^{४}.

आसीत ७. २०, ७.

आऽसीदंति १०. ८५, ३२.

आसीनः २. ४३, ३; १०. २७, १३.

आसीनं ८. १००, ५.

आसीनाः ३. ३१, १२; ९. ७८, ३.

आसीनासः १०. १५, ७.

आसीनेषु ६. ४७, १९.

आसीऽइत् १०. १२९, ५^{२}.

आसु १. १७३, ८; ४. ३७, १; ६. ५, ३; २८, ८; ४४, १८; ७. ६७, ६; ८८, ७; १०. ८६, ११; १४४, ३.

आसु १. ९५, ५; ३. ५५, ९; ४. ३८, ६; ६. ६१, १३; ७२, ४; ८. ४१, ७; ८; ९. ८६, ४३; ९९, ७; १०. २७, ८; ४९, १०^{२}; ६१, २०; ९५, ८; ९; १०४, ९.

आसुः ६. १९, ४; २१, ५; ११.

आसुः ४. ५१, ७; १०. ९२, ३.

आऽसुतिः ८. १, २६.

आऽसुतिं १. १०४, ७; २. १, १४; ७. ९७, ७.

आऽसुनोति १०. ४२, ५.

आसुरः ३. २९, ११; ५. ४०, ५.

आसुरस्य ५. ८५, ५.

आसुरे १०. १३१, ४.

आऽसुवंति ४. ५४, ६.

आसे ७. २०, ३.

आऽसेचनानि १. १६२, १३.

आस्क्राः १. १८६, २; ७. ४३, ५.

आस्क्रे इति ३. ६, ४.

आस्तं १. १२०, ७.

आस्तां ३. ४, ११; ८. ५९, २; १०. ८५, ९–११.

आस्तें ७. ५५, ६.

आस्ते १०. ७१, ११; १०७, १०; १३९, २.

आस्त्रऽबुध्नाय १०. १७१, ३.

आऽस्थाता ६. ४७, २६.

आस्नः १. ११६, १४; ११७, १६; ८. ६७, १४.

आस्ना ५. ७३, ६

आस्ने २. ३९, ६.

आस्यत् ४. ३०, २०; १०. ७२, ८; १३८, ३; ४.

आस्यं २. १, १३; १३, ८.

आस्यात् १०. ३९, १३.

आस्ये १. ३८, १४; १६२, ८; ४. ४९, १; ५. १२, १; ७. १५, १; १०२, ३; १०. ९१, ५; १५.

आस्येन १. ६१, ३.

आहं २. २८, १०; ४. २५, ४; ५. ३७, १; ७. ४१, २; १०४, १५; १६^{२}; ९. ७०, ९; १०. ४९, ७.

आह ४. १९, १०; ३३, ५^{२}; ५. ४४, १४; ७. १८, ४; ८. १, ३४; १००, ३; १०. २७, १८.

आऽहंतः १०. ८५, १२.

आहनः १०. १०, ६; ८.

आहनसः ९. ७५, ५.

आहनसं १०. १२५, २.

आहनाः २. १३, १; ५. ४२, १३.

आऽहवनानि ७. १, १७; ८, ५.

आऽहुवं १. १५५, ६; २. २३, ११.

आऽहुवे १०. १५०, ५.

आऽहुवेषु ६. ४७, १.

आऽहावः १०. ११२, ६.

आऽहावं ६. ७, २.

आऽहावाः १. ३४, ८.

आऽहावान् १०. १०१, ५.

आऽहितः ८. ५, १९; ९. १२, ५; ६४, १९; १०. ८५, २.

आऽहितं १. १६४, २३^{२}; ६. ९, ६; ८. २९, ४; १०. १३५, ४.

आऽहिता १. १६६, ९; ५. ७५, ४; १०. १४, १६.

आहुः १. ११८, ३; १६२, १२; १६३, ३; ४; ४. ३१, ७; १०. ५४, २; ८२, २; १२१, ४.

आहुः १. २४, १२; ७४, ५; १०४, ९; १६३, ४; १६४, १२^{२}; १५; १६; १९^{२}; २२; २५; ४६^{२}; २. १२, ५; ३. ४, ७; ४. २३, ३; ३८, ९; ४३, २; ५. ११, ६; ३०, २; ५३, ३; ७३, ९; ६. ४४, १०; ५२, ३; ७. २६, ४; ३३, १३; ८६, ३; ८. १९, २९; ९६, १९; ९. ११४, १; १०. १०, १२; २०, ७; ३१, ११; ३४, ४; ३९, ३; ४२, ३; ७१, ५; ९५, १८; १०७, ६; ११२, ९; ११४, ९; १२४, ९.

आऽहुत ३. २४, ३; ५. ११, ३; २८, ५; ७. १५, ७; ८. १९, २५; ४३, १३; ७५, ३.

आऽहुतः १. ३६, ८; २. ७, ४; ५; ८, २; ६. १६, ३४; ७. १, १६; ८. १९, १९; २२; २३; २५, १९; ४३, २२; ४४, २१; १०३, ९; १०. १६, ५; ६९, १; २; ११८, ३; ४.

आऽहुतं १. ९४, ३; ९६, ३; २. १, १३; १४; ३२, ६; ३. २८, ३; ५; ५२, ६; ५. ८, ६; ७; ७. ८, १; ८. ४३, १०; १०. ३६, ६; ५७, २; ८८, १.

आऽहुतस्य ७. ३, ५.

आऽहुताः १०. ९१, १४.

आऽहुतानि १०. ९८, १०.

आऽहुतिः १. १०५, ५; १०. २१, २; ५२, २.

आऽहुतिं १. ३१, ५; ९३, ३; १३५, ८; २. ३७, ६; ३. २८, ६; ६. २, ५; ७. ६६, १९; ८. १९, १८; २३, २१.

आहुतिऽवृधं ९. ६७, २९.

आऽहुंती ८. १९, ५.

आऽहुवः ८. ३२, १९.

आऽहुवध्यै ६. ६०, १३.

आऽहूर्यैः १. ६९, २.

आऽव्हर्यमानान् १०. ४८, ६.

इ

इक्ष्वाकुः १०. ६०, ४.

इंगय ४. ५७, ४.

इंगयंति १. १६४, ४५.

इच्छ १०. १०, १४.

इच्छ ६. ४७, १०; ५३, ६; १०. ८५, २१; २२.

इच्छत ७. १०४, १८.

इच्छत ८. ७०, १३.

इच्छति १. ८०, ६; ६. ५७, २; ९. ४७, ४; ११२, १; २; ४.

इच्छतु ७. १०२, १.

इच्छन् १. ८४, १४; १०९, १; १२५, ३; ३. ५४, २; ५. ३०, १; २; ७; ३१, १२; ७. ९८, १; १०. ५, ५; ८, ७; ४६, ३; ६७, ४; ७९, ३; १६५, १.

इच्छंतं १. ६८, ४.

इच्छंतः १. ७२, २; ११०, २; १६१, १४; १०. ४६, २.

इच्छंति ३. ३०, १; ५७, ३; ८. २, १८.

इच्छंति ८. ७२, ३; १०. १७७, १.

इच्छंती १. १६४, २७; ५. ३७, ३; १०. १०८, १; २.

इच्छंतीः १. २५, १६.

इच्छमानः १. १२६, १; १७९, ६; ३. १८, ३; ६. ६, १; ५८, ३; ७. ९३, ४; १०. ३४, १०; ६७, ६; ८१, १; १०२, ४.

इच्छमानं ४. १८, १०.

इच्छमानाः १. ११०, ५; ३. ३३, ७; ४. ४१, ९; ७. ९३, ३; १०. ४५, ११.

इच्छमानासः ३. २, ६.

इच्छसे ८. २१, १३.

इच्छस्व १०. १०, १०.

इच्छात् १०. २७, ९; ९५, १२.

इच्छामि ६. २८, ५.

इच्छामि ३. ३८, १.

इच्छेत् १०. ११७, ४.

इटतः १०. १७१, १.

इत १. १, ४; ६; ४, २; ५; ६; ७, १; २; ९, ५; १०; १०, ६; ७; १५, ५; १६, ८; १७, ६; २१, १; २२, १४; २४, १२; २५, ६; २६, ६; २७, ३; २८, १–४; ६; ३०, २; ३२, १५; ३३, २; ३४, २; ३६, १; ६; २०; ४०, २; ६; ४१, ८; ४६, १२; ४७, ८; ५१, ४; ८; १३; १४; ५२, ११; ५३, ३; ७; ५४, ९; ५५, ४; ५; ५९, १; २; ६१, १–१५; ६४, ८; ६७, ४; ६८, २; ७१, ३; ७२, ३; ६; ७४, ५; ७७, १; ७९; ११; ८०, १; ७; ८१, १; ८२, १; ८३, १; ६; ८४, २; ७; ८५, ८; ८७, ५; ८९, १; ९; ९२, ३; १०४, ५; १०५, २; १०६, ५; ११४, ३; ४; ८; ९; ११५, ४; ११६, ६[२]; १०; २५; ११७, १९; १२०, २; १२३, ४; ८; १२४, ६; १२५, ६; १२८, ६[२]; १२९, ११; १३१, ५; १३२, ५; ६[२]; १३३, ७; १३४, ६; १४०, १३; १४१, ४–६; १४४, ३; १४५, २; ३; १४७, ३; १४८, २; १४९, १; १५०, ३; १५२, ४; १५४, ३; १५५, २; ४[२]; ५; १५६, २; १६१, १; ४[२]; १६२, ३; २१; १६३, ७; ९; १६४, ८; १५; २२; २३; ३२; ३७; ४७; १६५, १०; १२; १६८, ९; १७०, ३; १७१, २; १७९, ३[२]; १८५, ८; १८७, ८–१०; १९०, ५; २. २, २; ११, ३[२]; ११; १५; १६[२]; १७; १३, १०; १४, १; २३, २; ५; १३; २४, ५; ९; ११; १२; २५, १; ५; २६, १[४]; ३; २८, ९; २९, ४; ३४, १४; ३५, ८; १०; ३७, २; ३९, १; ४१, ४; १९; ३. १, १४; २, १५; ४, ७; १०; ५, २; ६; ८, १०; ९, ९; १८, ५; २६, ८; २९, १५; ३०, ५; १२; ३१, ५; ११: १५; ३२, ४; ७; ३८, ३; ७; ४०, ६; ४२, ८; ४३, १; ५३, ४[२]; १३; ५४, ८; ५५, ३; ४. १, १; ८; १८[२]; २, ४; ५; १०; १६; ३, १२; १३; ४, ७[२]; ५, ३; ७; ७, ७; ९[२]; ८, ४; ९, ६; १२, ५; १६, १; १६; २०; १७, ५; १९, १; २१, २; २२, ५; १०; २३, १०; २४, ३; ४; ५[४]; ६; २५, ६; २९, ३; ३०, ३; ५; ८; ३२; ३१, ७; ८; ३२, ४; २०; ३३, २; ३५, ८; ३७, ६; ३९, ५; ४०, १[२]; ४१, ७; ४४, ४; ५०, ७; ८; ५१, ९; ५४, २; ५६, ३; ५. २, ४; ११; ३, ७; १२; १२, २; १६, ४; १७, ५; २५, २; २८, २; २९, १३; ३०, ४; ६; ८; ३१, ७; ३२, ३; ५; ३४, ४; ५; ३५, ६; ३६, ३; ३९, ५; ५३, ९; ५५, ६; ७; ५६, २; ५८, ५; ७; ५९, ५; ६०, ४; ६१, ८; ७३, ९; ७७, ४; ७९, ९; १०; ८१, १; ३; ५; ८५, ४; ७; ८६, ३; ६. १, ५; ९; १२; ३, ५; ७, ६; ९, ३; १४, २; १५, १; ११; १८, ४; १९, १३; २०, १३; २१, ३; २२, १; २३, १; १०[२]; २८, २[२]; ३; ५; २९, ६; ३०, १[२]; ४; ३३, २; ३४, ३; ४२, ३; ४; ४४, ५[२]; १०; ४५, ६; १७; ४६, १; ४७, १५; २२; ५०, ६; ९; ५१, ८; ५२,

१४; ६६, ३; ६; ६८, ५; ७०, ४; ७२, ४; ७५, ३; **७.** १, १४–१६; २, ३; ३, ५; ४, २; ८; ८, ५; ११, २; १६, ११; १८, ४; ६; ९; १४; २४; १९, ८; २०, ७; २२, ६; ७; २३, २; ६; २५, ४; २८, १; ५; २९, ४; ३१, २; ३२, ८^{२}; ९; १२; १४; १६; १८–२१; ३३, ३; ५; ६^{२}; ७; ९; ४०, ३; ४१, ५; ५६, २३; ५८, ३; ७२, ४; ७६, ३; ४; ८१, २; ८२, ४; ८५, ४; ८६, ३; ६; ९१, ३; ९४, १२; ९६, १; ३; ९८, १; २; ५; १००, ६; १०२, ३; १०४, १२; २१; **८.** १, १; ७; १४; १७; ३०; २, ४; १३^{२}; १७; २५; ३१; ३३; ३, ५; ८; १६; २४; ४, ९^{२}; ५, ३८; ३९; ६, १०–१२; १८; २१; २२; ३०; ३७; ४४; ९, ३; १०; १२, ८; १०–१२; २७; २४; २५; १३, ९; ११; १५; १७; १८; २०; २६; १४, १; १२; १६, ५; ६; १८, १४; १९; १९, ६; १४; १७; १८^{२}; २९; ३५; २०, १३; १७; २१, २; ७; १३; १४; १७; १८^{२}; २२, १४; २३, ८; १३; २४, १६; १९; २६, १७; २८, ४; ३०, १; ३१; १^{२}; २; १२; १५^{२}; ३२, १७^{२}; ३३, १०; १८; ३५, ७; ३६, ७; ३७, ४; ४०, १; २; ४२, १; ४३, ३; २९; ४४, १५; ४५, २; ३; १०; १९; ३०; ३१; ३३; ३९; ४६, १२; २९; ४७, ४; ६; ५१, ४; ७^{२}; ८^{२}; ९; ५३, ५; ८; ५४, ६; ५५, १; ५; ५६, ४; ५७, ३; ६०, ५; १०; १५; १६; ६१, ४; ११; १२; ६२, १२; ६६, ४^{२}; ६; १३; १५^{२}; ६७, ८; ६८, ७; ६९, ११; १३; १४; ७०, १४; ७१, २; ७२, ११; ७४, १०; १५; ७५, १४; ७६, ८; ९; ७७, ३; ५; ७; १०; ७८, ७; ९; १०; ७९, १; ५^{२}; ८०, ३; ६; ९; ८२, ७; ८३, १; ६; ९०, ५; ९२, ३; ५; ३२; ३३; ९३, १; ५; १८; ९६, १७; १९; ९७, १; ७; ९९, ३; १००, १; **९.** १, ५; १०; ११, ६^{२}; २१, ३; ४२, ४; ४७, २; ४८, ४; ५९, ४; ६१, १४; ६४, २; ७०, ३; ७३, २; ३; ७७, २; ८३, १; ९५, ३; ९६, १५; ९८, ७; ११२, ४; **१०.** २, ३; ४, ७; ५, ६; ७, ३; ८, ९; १३, ५; १४, १६; १६, ७; ११; १७, १०; १४; २०, ६; ८; २३, ३; ४; २७, २–५; ८; १०; १८; २०; २१; २८, १; २९, १; ३०, ६; ३१, ६; ३२, ३^{२}; ४^{२}; ८; ९; ३३, ८; ३४, ५; ७; ८; १३; ३५, ८; ३९, ३; ४; ४२, ९; ४३, २; ३^{२}; ४८, ५^{२}; ९; ५०, ५; ५१, ४; ५३, ११; ५४, २; ५; ५५, ६; ६१, २; ११; १३; ६२, ५^{२}; ६३, १६; ६८, २; ७३, ९; ७५, ४^{२}; ७६, ३; ८१, ४; ८२, १^{२}; ६; ८५, ४; ६; १६; ३४; ८६, ३; १४; १६; ८८, ८^{२}; ११^{२}; १७; ८९, ७; १०^{२}; १३; ९१, ३; ६; ८^{३}; ९; ९२, ३; ९३, १५; ९४, १०; १३^{२}; ९७, ५; ९९, ६; १००, १; ८; ११; १०१, ३; ७; १०६, १; १०८, ८; १०९, ३; १११, ९^{२}; ११२, ६; ११४, ८; ११५, १; ५; ६; ११६, ८; ११७, १; ३; ५–७; ११९, १०; १२०, १; १२१, ३; १२२, ७; १२४, ६; १२७, ३; १३२, १; १३६, ३; १३७, ६; १३९, ५; १४१, ४; १४५, ३; १४६, ५; १४७, २; ४; १५३, २; १५९, २; १६०, ३; १६८, ४; १७२, ३; १९१, १.

इत **८.** ८३, ७.

इत **१.** ५, १; ३३, १; **३.** ५३, ११; **५.** ४५, ६; **१०.** १४, ९^{२}; ३०, २; ३; १०३, १३; १०८, १०; ११.

इतऽऊति **१.** १५१, ९.

इतऊती इतीतःऽऊती **१०.** ३१, ७.

इतः **१.** ६, १०; ९८, १; ११९, ८; १३०, ५; १७९, ४; **३.** ४२, ३; **६.** २४, १०; ३८, १; ४७, ३०; **७.** ५०, २; ३; **८.** १८, ८; ३९, २; ९९, ७; **९.** ६३, १०; ७४, ३; ८१, २; ९७, ५४; १०७, १; **१०.** १७, ३; ६४, १४; ८५, २५; २६; १३५, ४; १४२, ७; १५५, २; १६२, १; ३.

इतः **८.** ३१, ६; **१०.** ८५, ११.

इतःऽऊति **७.** ६८, ६; **१०.** ६१, २.

इतःऽऊतिः **१.** १४६, २; **९.** ७४, ३.

इतन **३.** २९, ९; **५.** ६१, ४; ८७, ८; **१०.** ८५, ३३.

इतं **८.** १०१, ८.

इतरः **१०.** १६, ९; १८, १.

इतरं **१०.** १६, १०.

इतराः **६.** १६, १६.

इतां **२.** ४१, १९; **१०.** ८५, ३२.

इति **१.** १०९, ३; ११७, १८; १२२, १२; १३८, ३; १६१, ५; ८; ९^{२}; १६२, १२; १६४, १५; १९१, १^{२}; **२.** १२, ५^{२}; ३०, ७; **४.** १, १; २५, ४; ३३, ५^{३}; ३५, ३; **५.** २, १२; ७, १०; २७, ४; ३७, १; ४१, १७; ५२, ११; ५३, ३; ६१, ८; १८; **६.** ५४, १; २; ५६, ९; ६२, ७; **७.** ४१, २; १०४, १५; १६^{२}; **८.** ३०, २; ३२, १५; ७७, १; ९२, २; ९३, ५; १००, ३; **९.** ६, २; ३९, १; ६३, ९; १०१, ५; ११४, १; **१०.** १७, १; २४, ५; २७, ३; ३३, १; ३४, ६; ६१, १२; २६; ७३, १०; ९५, १८; ९७, ४; १०९, ३; ११५, ८; ९^{२}; ११९, १^{४}; १२०, ४; १३०, १; १४६, ४.

इत्थं **८.** ७०, १४.

इत्था **१.** २, ६; २४, ४; ३६, ७; ३९, १; ७; ८०, १; ८४, १०; १५; ९२, १७, १२०, २; १२१, १; १३२, ४; १३९, २; १४१, १; १५४, ५; १५५, २; १५९, १; १६५, ३; १७३, ६; **२.** ११, ११; ३५, ११; **३.** ९, ५; २७, ६; ३२, १६; ४२,

३; **४.** १०, ७; १६, ३; २४, ६; २९, ४; ४१, ३; **५.** १७, १; २०, ४; ३२, ६; ३३, १; २; ६१, १५; ६७, १; ८४, १; **६.** १६, १६; १८, ५; ३२, ५; ३३, ५; ४७, २०; ४९, ११; ५९, २; ६२, ३; ६७, ११; ६८, ८; **७.** ५६, १५; ९४, ५; **८.** २, ४०; ७, ३०; १३, २६; २५, १६; २८, ३; ३३, १०; ८५, ६; १०१, १; **९.** ८३, ४; **१०.** १, ३; २८, १०; ४४, ७; ६१, १; ९५, ११; १०२, १०; १०५, ११[२]; १५२, १.

इ॒त्थाऽधि॑ये ४. ११, ३; **९.** ६१, २.

इ॒त्थाऽधीः॑ २. २०, २.

इ॒त्या १. १६७, ५.

इ॒त्याः ७. ३६, ३.

इ॒त्यै १. ११३, ६; १२४, १.

इ॒त्व॒रं १०. ८८, ४.

इ॒थ॒ः १०. १०६, २.

इ॒दं १. १३, ७; १६, ५; २१, ४; २२, १७; २३, २२; २६, १०; ५१, १५; ५३, २; ३; ७; ७९, २; ९१, १०; ९३, २; ९८, १; १०२, ८; १०३, १; ५; १०८, २; ११३, १; १३; ११४, ६; १४०, ११; १५४, ३; १६१, ८[२]; ११; १३[२]; १६४, ३७; १८२, १; १८५, ११; **२.** ३, ४; ८; ५, ५; १२, १४; २८, १; ३२, १; ३३, १०; ३७, २; ३८, ९; ४१, १३; **३.** ४, ८; २४, ३; २९, १; ३१, ९; ५१, १०; ५३, ३; १२; ५४, ३; **४.** ५, ५; ६; ९; ११; १८, ६; ४९, १; ५१, १; **५.** ११, ५; २२, ४; २६, ९; ३०, १२; ४२, १३; ४७, ५; ७; ५४, १५; ७६, ४[२]; ८१, ५; ८३, ९; **६.** ९, ४; ६; २८, ८; ४४, १६; ४७, १०; ५४, १; ६०, ४; ६७, ८; ६८, ११; ७५, १५; **७.** ८, ६; २४, ३; ३५, १४; ३६, ५; ५५, ६; ५८, ६; ५९, ९; ८९, ५; ९१, ४; ५; ९८, ६; १०१, ५; **८.** १, ३; २, १; ४, १२; १७, १; १८, १; ३७, १; ३८, ३; ४०, ४; ४६, २८; ५७, १; ५८, २[२]; ६१, १; ६५, ८; ७३, ११; ७६, ४; ८४, ५; ९१, ५; **९.** २२, ५; ६; ८६, २८; **१०.** १४, १५; १५, २; १७, १; १८, ८; २७, २२; २८, ४; ३०, १५; ३९, १; ४०, १०; ४८, ७; ५६, १; ५८, १०; ६०, ७; ६१, १; १९; ६८, १२; ६९, ३; ४[२]; ७०, ८; ८५, १७; ८६, १२; ८७, ८; ८८, १५; १७; ९०, २; ९५, १६; ९६, १३; ९७, १४; २१; १०७, ८; १०; १०८, १; ३; ११०, ८; ११२, ६; ११४, ४; ११६, ७; १२४, ६[२]; १२५, ५; १२९, ३; १३५, ७; १३६, १; १४२, ७; १४९, ३; १५१, २; १५८, ४; १५९, ४; १६०, २; १६३, ५; १६५, १; १६७, १; १७३, ४.

इ॒दंऽइ॑दं ७. ५९, १; **८.** २१, ९.

इ॒दा ४. १०, ५[२]; ३३, ११; ३४, १; ४; **६.** २१, ५; ६५, ४[३]; ५; **८.** २२, ११; १३; २७, ११[२]; ६६, ७; ९९, १.

इ॒दानीं॑ १. ३५, ७; **४.** ५४, १; **५.** ७६, ३; **७.** ४१, ४; **१०.** ८७, ६.

इ॒द्धऽअ॑ग्नयः १. ८३, ४; **८.** २७, ७.

इ॒द्धः १. ९५, ९; ११२, १७; **५.** १, ६; **१०.** ४५, ४.

इ॒द्धं १. ६६, ५; ७३, ४.

इ॒द्धाऽसः ८. ४३, ५.

इ॒द्धे २. १५, ४; **६.** ६०, ११.

इ॒धु॒ते ७. १, ८.

इ॒धा॒नः १. ७९, ५; **२.** २, ८; **४.** १२, २; **६.** १०, २; ११, ६; १२, ६; **१०.** ४५, ५.

इ॒धा॒नाः ६. ६६, २; **७.** ३, ३.

इ॒धी॒म॒हि ३. २७, १५; **५.** ६, ४; १३, १; २१, १; २६, ३; **८.** २३, १६; **१०.** १६, १२.

इ॒ध्मः ८. ४५, २; **१०.** ९०, ६.

इ॒ध्मऽभृ॑तिः ६. २०, १३.

इ॒ध्मं १. ९४, ४; **४.** २, ६; १२, २; **१०.** ६१, ९.

इ॒ध्मेन॑ ३. १८, ३.

इ॒ध्यतें ८. ६, ३०.

इ॒ध्य॒ते १. १२, ६; **३.** १, २१; २६, ३; २७, १३; १४; **१०.** ९१, १; १५१, १.

इ॒ध्यमा॑नः ५. ३, ८.

इ॒ध्यसें ५. २१, २.

इ॒ध्य॒से १. ३१, १३; **३.** २१, ३; २४, २; २५, ५; **५.** २८, ४; **१०.** ६९, ८; ११८, ५; १५०, १; १९१, १.

इ॒नः १. ५३, २; १४९, १; १६४, २१; **२.** २०, २; **७.** २०, ५; ३६, २; **८.** २, ३५; ३३, ५; **१०.** ३, १; २६, ७[२]; ४४, ४; ५०, २; ११५, २.

इनं॑क्षत् १. १३२, ६.

इनं॑क्षतः १. ५१, ९.

इनं॑क्षन् १०. ४५, ७.

इनं॑क्षसि १०. ७५, ४.

इ॒नऽत॑मः ३. ४९, २.

इ॒नऽत॑मं १०. १२०, ६.

इ॒नधं॑ते ४. २, ७; १२, १.

इ॒नस्यं॑ १. १४९, १; १५५, ४; **९.** ७७, ४; **१०.** २३, ६.

इ॒ना ३. ३८, २.

इ॒नासः॑ ५. ५४, ८.

इ॒नु ९. २९, ४.

इ॒नु॒हि ६. १०, ७.

इ॒नोति॑ ६. ४, ३; **८.** ३९, ५.

इ॒नोपि॑ ४. १०, ७.

इ॒नो॒पि ६. ५, ३; **१०.** १२०, ७.

इं॒द॑वः १. २, ४; १४, ४; १५, १; १६, ६; ४६, ८; ९; ८४, ५; १३४, २; १३७, २; १३९, ६; **३.** ४०, ४; ५; **४.** ४७, २; ५०, १०; **६.** ४१, १; **७.** ३१, ९; **८.** १, १५; ३, ६; ४, ४; ६, २१; ३८; १३, १६; २१, ३; ४५, १४; ४८, ५; ४९, ३; ५०, ३; ४; ५१, १०; ५३, ३; ९२, २४; **९.** ६, ४; ७, १; १०, ४; १२, १; १३, ५; ७;

१६, ५; १७, २; २१, १; ३; २४, १; ४६, २; ३; ६२, १; ६३, ६; २५; २६; ६४, १६; १७; ६५, २४; ६६, १२; ६७, ७; ६८, १; ७७, ३; ७९, १; २; ८५, १; ७; ८६, १; २; १०१, ८; १०; १०६, १.

इंद्वः ९. २१, ५; १०६, ९.

इंदवे १. १२९, ६; ८. ६९, १; ९. ११, १; १०. १३, २.

इंदुः १. १२१, ६; १७५, १; २. २२, १–३; ६. ३९, ३; ४४, २१; २२; ८. ४८, १२; ९. ५, ९; १२, ५; ६; २७, ४; ६; ३०, २; ३४, १; ३५, ४; ३७, ६; ३८, ५; ४३, ५; ४५, ४; ६२, १५; ६३, ९; ६४, १०; ६६, २३; २८^{२}; ६७, ४; ८; ६८, ९; ७२, ४; ७६, २; ७७, ४; ८४, २; ४; ८५, ४; ८६, १६; २६; ८७, २; ९१, २; ९३, ३; ९६, ९; २३; ९७, ५; १०–१२; २४; ४०; ४१; ४५; ५६; ९८, २; ३; ९; १०१, २; ५; १०५, २; १०७, ३; २६; १०९, ९; १३; २२; ११०, १०; ११; १०. २६, ३; १४४, १.

इंदुना १०. १४४, ६.

इंदुऽभिः १. २३, १५; ३०, १; ५३, ४^{२}; ६. १६, १६; ४२, २; ३; ८. ६, २७; ७, १४; १२, १६–१८.

इंदुं १. १३५, ५; ३. ३५, ६; ५. १८, २; ६. ४०, २; ८. २४, १३; ९. ९, ५; ११, १; २६, २; ३२, २; ३८, २; ४३, २; ४५, ५; ५३, ४; ६०, १; ६१, १३; ६२, २९; ६३, १७; ६५, १; ८; ८८, १; ९४, २; ९७, २२; ५७; १०९, १२; २०; १०. ९९, ८; ११५, ३.

इंदून् ६. ४७, १४.

इंदो इति ८. ४८, २; ९. १, ५; ४, १०; ६; २; ८, ७; ११; ९; २३, ६; २४, ५; २६, ६; ३०, ५; ३१, ६; ३५, २; ४३, ४; ४५, १; ६; ५०, ५; ५२, ३; ५५, २; ५९, ४; ६३, २८; ३०; ६४, १२; १३; २५; ६५, १४; ६६, १४; ६७, ५; ६९, १०; ८१, ३; ८५, ८; ८६, १८; २३; २४; ९०, ६; ९३, ४; ९७, २९; ९८, १; ४; १०४, ५; १०५, ५; १०६, ७.

इंदो इति १. ४३, ८; ९१, १; १७६, १; ५; ४. २८, २; ३; ७. ५४, २; ८. ४८, ४; ८; १३; १५; ९. २, १; २; ७; ९; १०; १२, ९; १३, ४; २९, ६; ३१, २; ४०, ३; ४; ६^{२}; ४१, ४; ४४, १; ५१, ३; ५२, ४; ५; ५४, ४; ५६, ४; ५७, ४; ६१, १; ३; २६; २८; २९; ६२, ७; ९; २०; ६४, ३; २२; २६; २७; ६५, ५; १३; १७; ६६, १३; १६; ६७, ६; ७०, १०; ७२, ९; ७९, ५; ८२, ५; ८५, ३; ८६, २२; २८; ३७; ३९; ४१; ४७; ४८; ९०, ५^{२}; ९१, ४; ९३, ५; ९५, ५; ९६, ८; २१; ९७, १६; १७; १९; २१; २८; ३३; ४४; ५२; ५५; ९९, ८; १००, २; १०५, ४; ६; १०७, १९; १०. २५, ९.

इंदौ ८. ९२, ४; ९. ११४, १.

इंद्र १. ३, ४–६; ५, ६; ७, ४; ८, ३; ४; ९, १; ६; ८; १०, ४; ७; ९; १५, १; १६, १; ४०, १; ५१, १२; ५२, ८; ६१, १६; ८०, ३; ७; १४; ८४, १९; १०४, ७; १२९, ३; १३२, ४; १४२, १३; १६५, ५; ७; १७०, ५; २. १३, १३; १४, १२; १६, ६; १८, ६; २१, ६; ३. ३०, १; १५; ३१, २०; ३२, १; ३४, २; ३५, १; १०; ३६, २; ३; ९; १०; ३७, १–३; ६–९; ११; ३९, १; ४०, १–४; ६; ४१, ८; ४३, २; ३; ७; ४४, २; ४५, ४; ४६, १; ४७, ३; ५१, ७; ५२, १; ४; ५३, २; ५; २१; ६०, ५–७; ४. २९, १; ३०, ८; ३१, १२; ३२, ७; ९; १२; १३; ३७, ८; ४१, ११; ५. २९, १५; ३०, ३; ३१, ५; १०; ३५, १; ३८, ५; ४३, ५; ४६, २; ६. १९, ७; ९; २५, ३; ५; ७^{२}; ८; ९; २७, ३; ३०, ४; ५; ३५, २; ३७, १; ४०, १; ३; ४; ४१, १; ४४, १०; १८; २०; ४५, १०; २५; ४६, ५; ९; ११; ४७, ७; १०; ६०, ३; ७. २२, ९; २४, ५; ३२, २४; २६; ३६, ४; १०४, २४; ८. १, १३; २, ३; ११; १६; २९; ३, ७; १२; ४, २^{२}; ६, २६; ४१; १२, ५; १३, १२; २६; १४, ४; ११; १४; १५, ३; १७, १; ९; २१, १६; २४, ४; ९; १७; ३२, १९; ३३, २; ३६, ७; ३७, १; ४५, १३; ४६, १९; ४९, ५; ९; १०; ५२, २; ५३, ५; ६१, ४; ५; १६; १७; ६२, ४; ६३, ५; ६४, ३; ६५, ३; ५; ६६, ८; ११; १३; ६८, १; १०; ७६, ११; ७८, १; ८०, ४; ७; ८१, ६; ८; ८२, ६; ९०, ३; ९२, १६; ९५, १–५; ८; ९; ९७, ६; ९८, ५; ६; ९. १६, ५; १०. २४, १; ३; ६०, ५; ६४, १२; ९८, ४; १००, १; १०४, ३; ६; ९; ११२, १; ११६, २; १२८, ८; १३१, ५; १३४, ३; ४; १६०, १; २; १७१, १; १८०, १; ३.

इंद्र १. ४, ९; ५, ७; १०; ६, ५; ८, १; ९; ९, ४; ५; ७; १०, ३; ११; ११, २; ७; १५, ५; १६, ४; ६; २८, १–४; २९, १–७; ३२, ४; १२; १४; ३३, ३–५; ७; ९^{२}; १४; ५१, ४; १३; १५; ५२, ६; ७; १०; ११; १५; ५३, २; ३; ५; ७; १०; ११; ५४, ८; ११; ५५, ३; ७; ८; ५६, ५; ६; ५७, ४–६; ६२, ४; ५; १२; १३; ६३, १–९; ८०, ४; ८; ११; १३; ८१, ३; ५; ९; ८२, १–५; ८३, १; ८४, १; ४; ६; १००, १७; १०१,

९; १०; १०२, २–५; ८; १०; १०३, ३; ७; ८; १०४, १; ६; ८; ११०, ९; १२१, ११–१४; १२९, १; २; ९–११; १३०, १; २; ४; ५; ७; १०; १३१, ३^{२}; ४^{२}; ६; ७; १३३, ५; ६; १३९, ६; १६५, ३; १६७, १; १६९, १–६; ८; १७०, २; १७१, ६; १७३, १२; १३; १७४, १–१०; १७५, २; ६; १७६, ६; १७७, २^{२}; ४; ५; १७८, १; ५; **२.** ११, १–४; ६; ७; ११–१८; २१; १२, १५; १३, ११; १५, १०; १६, ३; ४; ९; १७, ८^{४}; ९; १८, ४; ५; ७; ९; १९, ७–९; २०, १; २; ९; २२, ४; २७, १४; ३०, ४; ५; ३६, १; **३.** ३०, ५–७; ८^{२}; ९; १०; १७–१९; ३१, १७; ३२, २; ३; ५; ६; ९; १०; १२; १६; ३५, ४; ६–८; ९^{२}; ३६, ३; १०; ३७, १०; ३९, ७; ४०, ५; ४१, ४; ७; ९; ४२, १; २; ७–९; ४३, ६; ४४, १; ४५, १; ५; ४६, ५; ४७, १; २; ४; ५१, ६; ८; १२; ५२, २; ५; ८; ५३, ६; १८; २२; २४; ५५, २२; **४.** १६, १९; २१; १७, ६; ७; १८^{२}; १९, १–३; ५; ६; २०, ३; ४; १०; २१, ९; २२, ५; ७; १०; २८, ४; २९, ५; ३०, १; ३–६; ९; १२; १४; १८; २२; २३; ३१, ६; १३; १४; ३२, ४; ६; ८; ११; १४; १५; २०; ३४, ७; ३५, ७; ४२, ७; ५०, ११; **५.** २९, १; ९; १४; ३०, ४; ८; ३१, २; ८; ३२, १; २; १२; ३३, २–७; ३५, २–५; ७; ८; ३६, ४; ३८, १; २; ३९, १; २; ४०, १; ६; ४२, ४; **६.** १७, १–५; ७; ८; ११; १२; १४^{२}; १८, ३; ९–११; १५; १९, ३; ८; १०; २०, १; २; ४; १०; ११; १३; २१, ४; ६; ८; १२; २२, ४; ९; १०; २३, १^{२}; २^{२}; ६–८; २४, ३; ४; ६; १०; २५, १; २; ९; २६, १; २; ४–८; २७, ४; ६; २८, ८; ३०, ३; ३१, १–३; ३३, १–५; ३४, १; ३५, २; ४; ३६, ४; ३९, ३; ४०, २; ३; ५; ४१, २; ४; ५; ४३, १; ४४, १; ११; १७; १८; ४५, १२; १३; १७; ३०; ४६, १; २; ७; १०; १३; ४७, ६; ८; ९; १४; २०; २२; ३१; ६०, २^{२}; ३; **७.** १८, १; ३; १८; २०; १९, १०; ११; २०, ४; ७; ८; १०; २१, ३; ५; ६; ८; ९; २२, १; २; ८; २३, २; ४; ५; २४, २; ४; ६; २५, १; २; ४; २७, २; ५; २८, १–४; २९, १; ३; ४; ३०, ३; ४; ३१, ३; ७; ३२, ११; १४; १६; १८; २२; २३; ३७, ४–६; ९८, २–४; ६; ९९, ६; १०४, ८; १९; २२; **८.** १, ३; ६; २३; २४; २८; २, १०; १५; ३, १; १०–१२; १४; १७–२०; ४, १; ४; ५; ९; ६, ९; १२; १४; १६–२०; २२–२५; ३१; ३२; ३६; ३९; १२, १; १६; २५; २९; ३१; ३३; १३, ४; ५; १३; २२; २७; ३१; १४, १; ३; ६; १०; १३; १५; १५, ८; १०; १२; १६, १२; १७, २; ३; ७; ११; २१, २; ४; ५; ७; १२; १३; १५; २४, २५; ३२, ३; ७; २०; २२; ३३, १३; ३६, १; ४०, ९; ४५, १०; १६; १९; ३१; ३२; ४१; ४६, १; ८; ४९, ३; ६; ५०, ७; ५१, १; ६; ७; ५२, १; ४; ८; ५३, १; ५४, १; २; ५; ८; ६१, ३; ७; ९; १३; १४; ६२, ३; ५; ७; ८; १०; ६३, ११; ६४, १२; ६५, ४; ८; ६६, ५; १२; ७०, ५; ९; १०; ७६, ७–१०; ७७, ७; ७८, ४; १०; ८०, १; ३; ८२, ३; ५; ७; ८३, ७; ८८, ३; ५; ८९, २; ९०, ३; ५; ६; ९१, ५; ७; ९२, ९; १०; १४; १७; २३; २४; २६; २९; ३१–३३; ९३, ४; ६; १०; २७; ३०; ९५, २; ९६, ४; ५; ७; ९; १६; १७; ९७, १–४; ७; ८; १४; १५; ९८, २–४; ७; १०; ९९, १; २; ५; ६; १००, १; ६; **९.** ९, ५; ७२, ४; ५; ८५, २; ८६, १३; ८७, ४; ८; ९७, ४६; **१०.** १९, ६; २२, ७; ९; ११–१३; २३, ६; ७; २८, ३; ७; २९, ३–६; ३२, २; ३३, ३; ३८, १–३; ५; ४२, ३; ४; ७; ४७, १; ३–५; ८; ५०, ३; ४; ५४, १; २; ५; ५७, १; ५९, १०; ६१, १५; २२; ६३, १४; ७३, ३; ४; ८; ७४, ४; ८५, २५; ४५; ८६, २; ४; १५; १८; २२; ८९, ८; ९; १२; १४; १५; १७; ९३, ११; ९६, ५; १२; १३; १०२, ३; १२; १०३, ५; १०४, १; २; ४; ५; ८; १११, १०; ११२, २–४; ५^{२}; ६–८; ११६, १; ३; ६–८; १३१, १; १३३, २–४; ७; १३४, १; १३८, १; १४८, १; २; ४; ५; १५२, ३–५; १५३, २–५; १६०, ५; १६४, ४; १६७, १; १६९, ३; १७१, ३; १७९, २; ३; १८०, २.

इंद्रऽइषितः **१०.** ८, ८.

इंद्रऽइषिताः ५. ३१, ५.

इंद्रऽइषितां २. ११, ८.

इंद्रः **१.** २, ५; ६; ५, ९; ७, २^{२}; ३; ९; ८, ५; १०, २; ६; ११, ४; १६, ८; १७, ५; १८, ४; ५; २३, २४; ३०, १६; ३२, ५; ९; १३; १५; ३३, १०–१३; ४०, ५; ५१, ९; ११; १४^{२}; ५२, २; ५; ५४, १०; ५५, २; ६१, ९; १०; १५; ८०, ५; ६; १०; ८१, १; ६; ८३, ६; ८४, ७–९; १३; ८५, ९; ८९, ६; ९०, ४; ९; १००, १–१५; १९; १०१, २; ४; ५; १०२, ६; ९; ११; १०७, २; ३; ११०, ७; १२५, २; १२९, ८; १३०, ३; ४; ८; १३२, २; ३; १३३, ७; १३५, ४; ७^{२}; १६१, ६; १६२, १; १६३, २; ९; १६४, १९; १६५, १०; १६६, १२; १७३,

४; ६; ९; १०; १७७, १; १७८, २^{२}; ३; ४; १८६, ६; **२.** १, ३; ११, ९; २०; १२, १–१४; १४, २; ६; १५, १–९; १९, १–६; २०, ३; ५–७; २१, ४; ३०, ३; ८; ३१, ३; ३८, ९; ४०, २; ४१, १०–१२; **३.** ४, ६; २२, १; २५, ४; ३०, ३, ११; १४; ३१, ४; ११; १५; ३३, ६; ३४, १; ३–५; ७; ९; १०; ३६, ५; ६; ८; ३९, ४–६; ४३, ४; ४४, ३; ५; ४५, २; ४६, ३; ४८, ४; ५०, १; ५१, ३; ५३, ९; १७; ५४, १५; ५७, १; २; **४.** १६, ५; १७, ५; १०–१२; १९; २०; १८, ३; ८; ११; १९, ४; ७; ८; २०, १; ६; २१, १; १०; २२, १; २३, ३; २४, २; ७; २५, ३; ६; ७; २७, ५; २८, १–३; ५; २९, ३; ३०, १६; १७; २०; २१; ३४, १; ३७, ६; ४२, ३; ५; ४३, ३; ४७, २; ३; ४९, ३; ५०, १०; ५४, ६; ५५, १०; ५७, ७; ५८, ४; **५.** २, ८; ३, १; २९, ३^{२}; ४; ७; ३०, ६; ९–११; ३१, १; ३; १२; ३२, ३; ६; ७; ३४, ६; ८; ३६, १; ३७, ४; ४०, ४; ४२, ५; ४९, ३; ५१, १४; **६.** १७, ९; १८, १; ८; १९, १; २०, ३; ५; ८; २१, ४; २२, ७; २३, ३; ९; १०^{२}; २४, ५; २७, १; २; ५; २८, २; ५; २९, ६; ३०, १; ३२, ५; ३४, २; ५; ३७, २; ४; ५^{२}; ३९, २; ४४, १२; १४; ४५, १; २; ४७, २; ११–१३; १६–१८; ५१, ११; ५२, ६; ११; ५६, २; ५७, ४; ६९, ८; **७.** १८, ४; ५; ९; ११; १३; १६; १७; २०, १–४; २१, १; ४; ७; २३, ३; २६, ३; ४; २७, ३; ४; ३२, १०; १२; ३३, २; ३; ५; ३४, ४; २५; ३५, ६; ४०, २; ४७, २; ४; ४८, ३; ४९, १; ५१, ३; ८२, १०; ८४, २; ९३, ८; ९७, १०; ९८, १; १०४, १६; २१; २५; **८.** २, ४^{२}; ३२; ३४; ३, ६^{२}; ८; २१; ४, ११; ६, १; ५; ११; १२, ९; १२; १३, १; १४, ७; १६, ५; ६; ७^{२}; ११; १७, ८; १४; २१, १७; २५, १४; २७, ६; ८; ३२, १२; १८; २८; ३३, ५; ९; १७; ३४, १६; ४०, ५; ४५, १; ७; ९; २६; ५२, १०; ६१, १; १५; ६२, ९; ६३, ३; ४; ६६, ३; ४; १०; ६७, ८; ६९, ७; ११; १४; ७०, ७; ७२, ८; ७६, २; ३; ७७, ४–६; १०; ७८, ५; ८९, २; ९०, १; ९२, २–४; ९३, ३; ८; ३२; ३४; ९४, ६; ९६, १२; १३; १५; १००, ३; ७; **९.** १, १०; ५, ७; ९; ११; ६, २; १९, २; २३, ७; ६३, ९; ८८, ४; ९५, ५; १०८, १४; १०९, २; ११३, १; **१०.** ८, ९; १९, २; २२, १; २; २३, २–४; २९, १; ८; ३०, ४; ३२, १; ३६, ५; ३७, ६; ४२, ११; ४३, ३; ४८, २; ५; ४९, ११; ५०, २; ६५, १; ६६, ३; ६७, ६; १२; ७३, ५; ६; १०; ७४, ६; ८३, २; ८६, १; १३; ८९, २; ३; ७; १०^{८}; ११; ९०, १३; ९२, ४; ६; ९३ ९; ९४, ९; १००, ४; ५; ११; १०२, १; ७; १०३, १; ३; ७; ८; ११; १३; १०४, १०; १०५, ३; ४^{२}; १०८, ३; १०; १११, ३; ५; ११३, २; ५; ७; ९; ११६, ४; १३८, ३; १३९, ३; ४; ६; १४४, ६; १५२, २; १५७, १–३; १५९, ४; १६०, ३; १६१, ३; १७३, ३; ५; ६; १७४, १.

इंद्रः॒ऽइव **१०.** ८४, ५; १६६, २; १७३, २.

इंद्र॑ऽगोपाः **८.** ४६, ३२.

इंद्र॑ऽजूतः **३.** ३३, ११.

इंद्र॑ऽजूतं **१.** ११८, ९.

इंद्र॑ऽज्येष्ठाः **१.** २३, ८; **२.** ४१, १५; **५.** ५१, १५; **८.** ६३, १२.

इंद्र॑ऽज्येष्ठान् **४.** ५४, ५; **१०.** ७०, ४.

इंद्र॑ऽज्येष्ठासः **७.** ११, ५; **१०.** ६६, १.

इंद्र॑ऽतमा **१.** १८२, २; **७.** ७९, ३.

इंद्र॑त्वाऽऊताः **१.** १३२, १; **८.** १९, १६.

इंद्र॑ऽद्विष्टां **९.** ७३, ५.

इंद्र॑नासत्या **८.** २६, ८.

इंद्र॑ऽपत्नी **१०.** ८६, ९; १०.

इं॒द्र॒ऽपात॑मः **९.** ९९, ३.

इं॒द्र॒ऽपानः॑ **९.** ९६, ३; १३.

इं॒द्र॒ऽपानं॑ **६.** ४४, १६; **७.** ४७, १; **१०.** ३०, ९.

इं॒द्र॒ऽपानाः॑ **१.** ५४, ९.

इंद्र॑ऽपीतं **९.** ८, ९.

इंद्र॑ऽप्रसूताः **१०.** ६६, २.

इंद्रे॑ **१.** ४, ४; ५, १; २; ६, १०; ७, १^{२}; ५^{२}; १०; ९, ९; ११, १; ८; १६, २; ३^{३}; २३, ७; ३०, १; ७; ३२, ७; ३३, १; २; ८; ५१, १; २; ५२, १; ३; ४; ९; ५४, २; ५५, १; ५६, ४; ८०, १२; १५; ८४, २; १७; ८७, ५; १०१, ६; ७; १०२, १; १०४, २; १०६, १; ६; १११, ४; १२९, ४; ७; १३१, १; २^{२}; १३६, ६; १४२, ४; १६४, ४६; १७३, ५; ७; ११; १७६, १; **२.** ३, ३; ११, ११; १४, ३; ४; १०; ११; १६, १; ७; २०, ४; २२, १–३; **३.** १२, ३; ३०, २२; ३२, ७; १३–१५; ३४, ८; ३५, २; ३७, ५; ३९, १; ४०, ७; ४१, ५; ४२, ३; ४; ४६, ४; ४७, ५; ४९, १; ५०, ३; ५१, १; २; ९; ५३, १२; **४.** २, १७; १६, १५; १६; १७, ८; १६; १८, ५; १०; २०, ५; २१, ४; ५; २४, १; १०; २५, ८^{५}; ३२, १७; ३५, १; ३९, ४; ४१, ८; ९; ४२, ८; **५.** २९, २; ६; १२; ३०, १; २; १३; ३१, ४; ३२, ११; ३९, ४; **६.** ४, ७; १७, ८; १३; १९, २; ४; २०, ९; २१, ९; २२, १; ३; ५; २४, ७; २८, ५; २९, १; ४; ३४, ३; ३६, ३; ३७, ३; ३८, २; ३^{९};

४[२]; ४२, २; ४४, ४; ४६, ३; ४७, १; ११[४]; ४८, १४; ५०, ६; ५७, ६; ६०, १२; ६१, ५; **७.** १०, ४; १८; १९; २४; २१, ७; २३, १; ६; २४, २; २६, १; २; ५; २७, १; २८, ५; ३१, १२; ३२, २०; ३३, २; ३७, ७; ३९, ५; ४१, १; ४४, १; ८३, ६; ८४, ५; ८५, ३; ९३, ७; ९७, ३; १०४, २०; **८.** १, १; १०; १५; २, ३७; ३, ५[४]; १६; ४, १४; ६, ३; १५; ३४; ३५; ४४[२]; ७, २४; ३१; १२, २०; २२[२]; १३, ३; १६[२]; १७; १४, ५; १२; १५, १; १३; १६, १; ९; १७, १५; २१, ९; २४, १९; २२; ३२, १३; ४०, २; ४६, ६; १२; १४; ४८, १०; ४९, १; ५१, ३; ५; ५२, ६; १०; ५४, २; ६१, ८; १०; ११; ६२, १२; ६४, ८; ६६, १; ६८, ६; ७; ६९, ४; ७०, २; ३; ८; ७४, १०; ७६, १; ५; ६; ८८, १; ९२, ५; २०; ९३, ७; २३; २५; २६; ९५, ६; ९६, ५; ९७, १०; ११; १३; ९९, ८; **९.** २, १; ६, ४; ७, ७; १२, २; १७, २; २४, २; २५, ५; २७, ६; ४०, २; ४६, ३; ६१, २२; ६३, ५; ६; २२; ६६, २८; २९; ६७, ७; ६९, ९; ७५, ५; ८०, ५; ८४, ३; ८५, ७; ८६, २; ४१; ९०, १; ५[२]; ९६, २१; ९७, ५; ६; ३६; ४९; १०६, १; ८; १०८, १४; ११०, ८; १११, ३; **१०.** ६, ५; २३, १; ३५, १०; ३६, १; ३८, ४; ४२, १; २; ८; ४३, १; ४; ७; ४७, ७; ४८, ६; ४९, २; ६३, ९; ७०, ११; ७३, १; २; ११; ७४, ५; ७६, १; ८६, १; ८९, १; ५; १३; ९४, ४; ९६, ६; ९९, १२; १०१, १२; १०३, ६; १०४, ७; १११, १; १२०, ९; १२४, ४; ९; १२६, ५; १३१, ४; १४१, ५; १५३, १.

इंद्रऽमार्दनासः **७.** ९२, ४.

इंद्रेऽइंद्रं **८.** १२, १९.

इंद्रेऽइव **१.** ११९, १०; **४.** ३९, ५.

इंद्रयंते **४.** २४, ४.

इंद्रऽयुः **९.** २, ९; ६, ९; ५४, ४.

इंद्रेऽवतः **४.** २७, ४; **१०.** १०१, १.

इंद्रेऽवंतः **१.** १०५, १९; १३६, ७; **४.** ३३, ३; ३४, ६; **५.** ५७, १; **१०.** ३५, १; १२८, २.

इंद्रेऽवंता **१.** ११६, २१.

इंद्रेवातऽतमाः **१०.** ६, ६.

इंद्रेवायू इति **१.** २, ४; १३५, ५; **२.** ४१, ३; **४.** ४६, ३–७; ४७, ४; **७.** ९०, ५; ६; ९१, २; ४–६.

इंद्रवायू इति **१.** १४, ३; २३, २; ३; १३९, १; **७.** ९०, ७; **१०.** ६५, ९; १४१, ४.

इंद्रऽवाहः **१०.** ४४, ३.

इंद्रऽवाहा **१.** १११, १; **८.** ९८, ९.

इंद्रऽवाहौ **४.** ३५, ५.

इंद्रेऽशत्रुः **१.** ३२, ६; १०.

इंद्रेऽसखा **७.** ३४, २४.

इंद्रेऽसारथिः **३.** ४६, २; ४८, २.

इंद्रऽसेना **१०.** १०२, २.

इंद्रेस्य **१.** ४, ६; ६, ८; ७, ७; ११, ३; १८, ६; २२, १९; ३२, १; ५७, २; ६२, ३; ८४, ११; १०१, ३; १०३, ५; १६७, १०; १७६, ५; **२.** ८, ६; १८, ३; २१, ३; **३.** ३०, १३; ३२, ४; ८; ३३, ७; ३४, ६; ३७, ४; ६०, ३; **४.** १७, ४; १८, ७; २५, १; २; ३३, ९; ३७, ४; **५.** ३२, ९; **६.** २४, ८; ३८, २; ४४, १६; ४७, २७; २८; ३०; ५५, ५; ५७, ५; ६०, ११; **७.** १८, १४; ४७, ३; ५५, ३; ९८, ५; १०४, १३; **८.** २, ७; १२, ११; ३१, १; ३२, १; ४८, २; ५०, २; ५५, १; ६२, १[२]; ६६, ९; ९२, २५; ९६, ३[३]; ९९, ३; १००, १२; **९.** ८, १; ३; १३, १; १५, १; २४, ५; ५६, २; ६०, ३; ४; ६१, १४; २५; ६४, १५; ६५, १४; ६६, १५; ७०, ९; १०; ७२, २; ७; ७३, २; ७६, २; ३; ७७, १; ८०, ३; ८१, १; ८४, ४; ८५, ३; ५; ८६, ९; १६; १९; २०; २२; २३; ९६, २; ५; ९७, ११; २५; ४३; १०१, ६; १६; १०८, १६; १०९, १४; १८; **१०.** २५, ९; १०; ५०, १; ५२, ५; ६२, १; ९४, ९; १००, ६; १०३, ९; १०८, २; १११, ८; ११३, ६; ८; ११४, ९; १३०, ५; १३८, ५; १५५, ४; १७९, १.

इंद्रेस्यऽइव **७.** ६, १; **९.** ९७, १३; **१०.** १७८, २.

इंद्रेस्वतं **४.** ३७, ५.

इंद्रऽहुवान् **९.** ९६, १.

इंद्रेऽहूतिं **६.** ३८, १.

इंद्रा **३.** ४१, १–४; ६; **५.** ४५, ४; **६.** ५७, १; ५९, ३; ६०, १; ६८, ५.

इंद्राकुत्सा **५.** ३१, ९.

इंद्राग्निऽभ्यां **१.** १०९, ३; **५.** ८६, ६; **८.** ४०, ५; १२; **१०.** ११६, ९; १२८, ९.

इंद्राग्नी इति **१.** २१, ५; ६; १०९, १; २; ४; **३.** १२, १; २; ५–९; **५.** २७, ६; ८६, १; **६.** ५९, १; २; ५–१०; ६०, ७–९; १५; **७.** ९३, १; ४; ९४, १–३; ७; ९; **८.** ३८, १; ४; ७; ४०, १.

इंद्राग्नी इति **१.** २१, १–४; १३९, ९; **३.** १२, ४; **५.** ४६, ३; ८६, २; ४; **६.** ६०, ४; ५; १४; **७.** ३५, १; ९३, ३; ९४, १०; **८.** ४०, ३; ४; ७; **१०.** ६५, २; १२५, १; १६१, ४.

इंद्राग्नी इति **१.** १०८, १–५; ७–१३; १०९, ५–८; **६.** ५९, ४; ६०, १३; **७.** ९३, ६; **१०.** १६१, १.

इंद्राग्न्योः **८.** ३८, १०; ४०, ८.

इंद्राणि **१०.** ८६, १२.

इंद्राणी **५.** ४६, ८.

इंद्राणीं **१.** २२, १२; **२.** ३२, ८; **१०.** ८६, ११.

इंद्रात् **१.** ३३, ६; १७१, ४; **२.** १६, २; **५.** ३०, ५; **८.** १५, ११; ७६, १२; **९.** ६९, ६; **१०.** ९२, ८.

इंद्रापर्वता ३. ५३, १.

इंद्रापर्वता १. १२२, ३; १३२, ६.

इंद्रापूषणा ७. ३५, १.

इंद्रापूष्णोः १. १६२, २.

इंद्राबृहस्पती इति ४. ४९, ५.

इंद्राबृहस्पती इति ४. ५९, १–४; ६.

इंद्राब्रह्मणस्पती इति २. २४, १२.

इंद्रामरुतः २. २९, ३.

इंद्राय १. ४, १०; ५, ४; ८, १०; ९, २; १०; १०, ५; १३, १२; २०, २; २८, ६; ८; ५३, १; ५५, ५; ६१, १; २; ४; ५; ८; ८०, ९; ८४, ५; १३१, १[२]; १४२, ५; १२; १५६, ५; १६५, ११; २. १४, १; ५; ८; ९; २०, ८; २१, १; २; ३०, १; ३. ३०, २०; ३१, १३; ३६, २; ७; ५१, ५; ५३, ३[२]; १३; ४. १६, २०; २४, ६; ७; २५, ४; ३३, १०; ५. ५, ११; २९, ८; ३२, १०; ३३, १; ३७, १; ५; ३९, ५; ५१, ४; ७; ६. २३, ५[२]; २८, १; ३४, ५; ४१, ३; ४४, ६; १३; ७. ३१, १; ११; ३२, ४; ८; ८५, १; ९२, २; ९७, १; ९; ८. १, १९; २, २३; ४, १३; १२, १४; २४, १; १३; ३३, ४; ४५, २१; ५२, ९; ६९, ६; ९; १०; ८९, १; ३; ९१, १; ३; ९२, १९; ९६, १; १०; ९८, १; १००, ३; ९. १, १; ९; ४, ४; ६, ७; ११, ८; १२, १; १३, ८; १६, ३; २१, १; २३, ६; २४, ३; २६, ६; २७, २; ३०, ५; ६; ३२, २; ३३, ३; ३४, २; ४; ३७, ६; ३८, २; ३९, ५; ४३, २; ४५, १; २; ४६, ६; ५०, ५; ५१, १; २; ५३, ४; ५६, ४; ६१, १२; ६२, ८; १४; १५; २९; ६३, २; ३; १०; १५; १७; १९; ६४, १२; २२; ६५, ८; २०; ६६, ७; ६७, २; ८; १६; ६९, १०; ७४, ९; ७६, ५; ७८, २; ८०, २; ८४, १; ८५, १; ४; ६; ८६, ३५; ८९, ७; ९६, ८; ९; ९७, १४; ३२; ४४; ९९, ८; १००, ५; ६; १०१, ४; ५; १०६, २; ५; १०७, १७; १०८, १; १५; १०९, १; १९; २०; २२; ११०, ११; १०. २७, २२; २९, ७; ३०, ७; १३; १५; ५४, ६; ६७, १; ७६, ८; ८९, ४; ९४, १; ९६, २; ६; ९८, ११; १२०, ८; १३३, १.

इंद्रावरुणयोः १. १७, १.

इंद्रावरुणा ६. ६८, ३; ७. ३५, १; ८२, २.

इंद्रावरुणा १. १७, ३; ७–९; ६. ६८, १०; ११; ७. ८२, १; ३–५; ७; ८३, ३; ४; ८. ५९, १; २; ६; ७.

इंद्रावरुणा ३. ६२, १–३; ४. ४१, १; ४२, ९; १०; ६. ६८, ४; ७; ८; ७. ८२, ८; ९; ८३, १; २; ७; ९; ८४, १; ४; ८. ५९, ३–५.

इंद्रावरुणौ ६. ६८, १.

इंद्रावरुणौ ७. ८३, ५.

इंद्रावरुणौ ६. ६८, ६; ७. ८३, ८; ८५, २.

इंद्राविष्णू इति ४. २, ४; ६. ६९, २; ८. १०, २; १०. ६६, ४.

इंद्राविष्णू इति १. १५५, २; ४. ५५, ४; ६. ६९, १; ३–७; ७. ९९, ५.

इंद्रासोमा ७. ३५, १.

इंद्रासोमा २. ३०, ६; ६. ७२, १; २; ४; ५; ७. १०४, १–४; ६; ७.

इंद्रासोमौ ६. ७२, ३.

इंद्रियः ८. ३, २०; ९. ४७, ३; ८६, १०.

इंद्रियं १. ५५, ४; ५७, ३; ८४, १; ८५, २; १०३, १; १११, २; २. १६, ३; ४. २४, ५; ३०, २३; ६. २७, ३; ४; ८. ३, १३; १२, ८; १५, ७; ५२, ७; ५९, ५; ९३, २७; ९. २३, ५; ३०, २; ४८, ५; ९२, १; १०. ३६, ८; ६५, १०; ११३, १; ३; १२४, ८.

इंद्रियाः ९. १०७, २५.

इंद्रियाणि ३. ३७, ९; ५. ३१, ३.

इंद्रियाय १. १०४, ६; ६. २५, ८; ९. ७०, ५; ८६, ३; ८९, ६; १०. ११६, १.

इंद्रियेण १. १६५, ८.

इंद्रियेभिः ४. ३५, ९.

इंद्रियैः १. १०७, २.

इंद्रे १. ४, ५; ३०, १३; ८०, १६; १३२, ५; १६६, ११; २. १४, ८; २१, ५; ३. ५४, १७; ४. २५, ५; ६. २४, १; ३४, १; ४; ७. २०, ६; २५, ५; ३२, २; १३; ३३, ४; ४२, ५; ९४, ४; ८. ३, ६[२]; १३, १६; ५४, ७; ६३, ६; ७; ७२, १५; ९. ११, ६; ९६, १२; ९७, १०; ४१; १०. ४२, ६; ९२, ७; ९६, ३.

इंद्रेण १. ६, ७; १४, १०; २०, ५; २३, ९; ५३, ४; ८४, १०; १०१, ११; २. १८, ८; २३, १८; ३. ४, ११; ६०, ४; ४. ३४, ११; ५. ११, २; ५१, १०; ६. ४४, २२; ४७, २९; ७. १८, १५; ३२, ६; ४८, २; ८. ९, १२; १४, ९; ३५, १; ४०, ६; ७६, ४; ९१, ४; ९६, ६; ९. ११, ९; ६१, ८; ८७, ९; १०३, ५; १०. १५, १०; ६२, ७; १०३, २; १०८, ४.

इंद्रेषिते इतींद्रऽइषिते ३. ३३, २.

इंद्रोते ८. ६८, १५; १७.

इंधतां १. १७०, ४.

इंधते १. ४४, ७; २. ३५, ११; ६. १६, ४८; १०. ६९, १.

इंधते ४. ८, ५; ५. ७, २; ८. ४३, २७; ४५, १.

इंधते १. २२, २१; ३६, ४; ७; ४४, ८; ३. १०, १; ९; १३, ५; २७, ११; ६. २, ३; ७. १६, ३; ८. ६०, १५.

इंधन्वऽभिः २. ३४, ५.

इंधानः १. १४३, ७; २. २५, १; ८. १९, ३१; १०२, २२; १०. ४५, १.

इंधानाः १०. ३, ४; १२८, १.

इंधानासः ८. २३, ११.

इंधे ७. १, १६; ८, १.
इंध्वं १०. १०१, १.
इन्व ५. ४, ७.
इन्वतः १. १०, ८; १४१, ४.
इन्वतं १. १६०, ५; ७. ६४, २.
इन्वतां ६. ७०, ६.
इन्वति १. ५४, ७; ५५, ४; १२८, ५, ६. ५, १; ९. २०, २.
इन्वति १. १८, ७; २. ५, २; ४. ५३, ५; ७. ८४, २; ८. १५, ११; ५२, ६.
इन्वतु १. १६२, ६; १२; ४. ५३, ७; १०. १८८, ३.
इन्वथः १. ११९, ७.
इन्वन् ५. ३०, ७; ९. ९७, १०.
इन्वतः ३. ४, ५.
इन्वसि ५. २८, २; ८. १३, ३२.
इन्वसि १. ९४, १०; १४१, १०; १७६, १; ९. १०७, २१.
इन्वात् १०. १६, १०.
इन्विरे ५. ६, ६.
इभः ९. ५७, ३.
इभे ६. २०, ८.
इभाय १. ८४, १७.
इभेन ४. ४, १.
इभ्यान् १. ६५, ४.
इमः ८. ९६, ८.
इमऽथा ५. ४४, १.
इमं १. ५, ९; १०, ९; १२, १२; १३, ८; १४, ११; १६, ५; २२, १३; २५, १९; २६, १, १०; २७, ४; ३१, १६; ८४, ४; ९१, १०; ९३, १; ९४, १; ९५, २; ४; १०२, ९; ११८, ३; १३५, ५; १३९, ११; १४२, ८; १६४, ३; १७९, ५; १८८, ७; २. ४, २; २७, २; ३५, २; ४१, १३; २०; ३. १, २२; ४, २; ५; १२, २; १६, २; १७, २; २१, १; ३०, २०; ३२, १; ३४, ५; ३५, २; ६; ८; ४२, ७; ५४, १; १०; ४. १४, ६; २०, २; ३; २४, १०; ३४, १; ६; ४४, ४; ५८, १०; ५. २, १२; ४, ५; ५, २; ७; ४०, ७; ६५, ६; ७१, १; ७४, १०; ६. ९, ४; १०, ६; १५, १; १७; ३९, ३; ५२, १२; १३; ५६, ५; ६८, १०; ७. ११, ५; १८, २५; ४२, ५; ५१, १; ८. २, ११; ६, ३६; ७, ९^{२}; ८, १२; १७; १२, ४; ५; १७, १; २३, १९; ३२, २१; ४३, १६; २२; २४; ४५, १८; ४६, २७; ५८, १; ६६, ८; ७३, ५; १०; ७६, १; ८५, २^{२}; ८६, ३; ९१, २; ९. १, ९; ५, ८; १०. १४, ४; १५, ६; १६, ८; १०; १४; १७, ११; १८, ४; १३; २४, १; २६, ९; ४४, ९; ४६, ३; ७५, ५; ८६, ४; ९२, २; ९७, २; १०२, ९; १०३, ६; १२३, १; १२४, १; १२८, ७; १३०, ६; १६१, ३; ४; १६७, २; ४; १७३, ३.
इमसि १. १, ७; १६१, ३; ८. ९१, ३.
इमस्य ८. १३, २१.
इमा १. १०३, ४; १२२, ६; १६३, ५; १६४, २; ६; १६५, ४; १४; १७७, ४; २. १२, ४; २४, १०; ४१, १८; ३. १, २०; १४, ७; २१, १; ३०, २; ४१, ३; ५५, १९; ५८, ४; ४. ३८, १०; ५. ७३, १०; ८२, ९; ६. १६, ५; ४०, ४; ५२, ११; ७. २२, ३; ४; ७; २९, २; ३; ५९, ५; ६२, ५; ७०, ६; ७; ९५, ५; १०४, ६; ८. ८, १७; ९, १४; ३८, ५; ४४, ८; ५१, ४; ९०, ३; ९६, ६; ९. ६२, २७; ८६, ३०; ३७; ९६, ७; ११०, ९; १०. १५, ४; ३२, ८; ६६, १२; ८१, १; ५; ८२, ७; ११२, ७; ११६, ८; १२०, ८; १४८, ४; १५७, १; १७०, ४.
इमाः १. १०, १२; १६, २; २४, ६; २६, ५; ३६, ११; ४५, ५; ८०, ४; ९१, २२; ९६, २; ११४, १; १२७, २; १३१, ४^{२}; १९०, ४; २. ६, १; ११, १; २७, १; ३९, ७; ३. ३४, ५; ३८, २; ५; ३९, ७; ४०, ८; ४३, २; ५७, ४; ६२, १; ४. ३, २; ३४, ५; ४१, ९; ६. २१, १; २८, ५; ४५, २५; ४७, ३१; ७. १८, ३; ४५, ४; ४६, १; ६१, ५; ८. ३, ३; ६, ७; १९; ७, १९; १३, २९; ५७, ४; ९. ३४, ६; ८६, २८; २९; १०. ७, २; १७, ५; १८, ७; ३०, १४; ४३, ८; ९१, १२; ९७, ११; १०८, ५; १२१, ४; १५९, ६.
इमान् ४. ३, १५; ५. ५०, २; ५३, ३; ९. ९७, १७; १०. ६०, ९; १५५, ५; १६६, ३.
इमानि १. ९३, ११; १२५, ६; ३. ६०, ६; ७. ६१, ६; ८२, ५; ८. ५९, १; ९१, ५; १०. ८२, ४.
इमां १. ३१, १६; ४०, ६; ८८, ४; १०२, १; १२९, १; १३०, ६; २. ६, १^{२}; २४, १; ३. १८, ३; ३२, ८; ३४, ८; ३६, १; ५४, १७; ५५, २१; ४. ५, २; ४३, १; ५७, ५^{२}; ५. ५४, १; ८५, ५; ६; ६. ४७, २८; ७. १५, ६; २२, ३; ३६, २; ४१, ३; ७०, ७; ७३, ३; ९३, ६; ८. ५, ३०; ६, ३२; ४३; ७, ९; ८, ६; १२, ३१; ३८, ६; ४२, ३; ९१, ६; ९. ९६, ३; ९७, १३; १०. ६७, १; ८५, ३३; ४१; ४५; ८८, ३; ९८, १६; ९१, १३; ११९, ८; ९; १२१, १; १४५, १.
इमे १. २, १; ४; ३, ४; ५, ५; १६, ६; २३, १; ५७, ४; १०२, ५; १०९, ७; १३५, ६; ९; १३७, १^{३}; २; १३९, ६; १६४, १२; ३९; १८३, ४; ३. ३६, ३; ४०, ४; ४३, १; ५३, ७; २४; ४. १४, ४; ५. ३, १२; ७६, ४; ७९, ५; ६. १७, ४; २१, १०; २३, ८^{२}; ५४, २; ६०, ७; ७. १, १०; ३२, २; ४; ५६, १९^{३}; २०; ५७, ३; ६०, ५^{२}; ६;

७; ९७, ५; ८. १, ३; २, १०; ३. १८; ५, ३९; ९, ८; १४^{२}; २१, ३; ४०, ७; ४३, १; २९; ४५, १६; ४६, ३२; ४७, ४; ४८, ५; ७४, ६; ९३, २२; २५; ९. ६६, ६; ८६, ३९; ९६, ४; १०६, १; १०. १८, ३; २५, २; ४३, ३; ६१, १९; ७१, ९; ९५, १८; १२१, ४; १३०, १; २; १४२, ८; १५५, ५; १६०, १; १६६, २; १७३, ४.

इमे इर्ति १. ८०, ११; १५८, ४; ३. ३०, ५; ५३, १२; ४. ५६, ३; ५. ३२, ९; ८२, ८; ६. ४६, ५; ७५, ४; ७. ३२, ४; ७२, ३; ८७, २; ९०, ३; ८. ६, १७; १०; ६; ९. १८, ५; ७४, २; ९७, ५४; ११०, ९; १०. ११०, ९; ११२, ४.

इमो इर्ति ७. १, १८.

इमौ २. ४०, २^{२}; १०. १३७, २.

इर्यक्षति ८. ३१, १५; १०. ११, ६.

इयक्षति ९. ७८, १.

इर्यक्षते ९. ११, १.

इर्यक्षन् १. १५३, २; १०. ७४, १.

इर्यक्षंतः २. २०, १; ६. २१, ३; ९. २२, ४; ६६, १४.

इर्यक्षंति ९. ६४, २१.

इर्यक्षमाणं १. १२३, १०.

इयक्षवें १०. ४, १.

इर्यक्षसि ८. ४५, ३१.

इयक्षसि ६. ४९, ४; ८. ४६, १७.

इर्यक्षान् १०. ५०, ३.

इर्यंत् ८. २१, १७.

इयत्तकः १. १९१, १५.

इयत्तिका १. १९१, ११.

इर्यत्यै ७. ४२, ४.

इयथ ८. १, ७.

इयध्यै ६. २०, ८.

इर्यंति ६. २३, ४.

इयं १. ४८, ७; ५७, ५; ६३, ६; १२४, ११; १२५, ५; १४२, ४; १६४, २७; ३३; ३५; १६५, १५; १६६, १५; १६७, ११; १६८, १०; १८३, २; ४; १८५, ८; १८६, ११; ३. ३९, २; ६२, ७; ५. ११, ५; ३७, ३; ५४, ९; ५७, १; ६. २३, ८; २७, ८; ३८, २^{२}; ५९, ६; ६१, १; २; ६७, २; ७५, ३; ७. २४, २; ६०, १२; ६६, ८^{२}; ७०, ७^{२}; ८४, ५; ९४, १; ९७, ९; ९९, ६; १०४, ६; ८. १, २६; १२, १०; १३, ४; ४०, ४; ६३, ८; ६७, १५; ७४, ७; ७५, १३; ८०, ७; १०१, १३; १०. ४, ६; ७; ३१, ५; ३५, ४; ३९, ६; ६०, ९; ६१, १९; ७४, ३; ८५, २५; ३३; १०९, ३; १२९, ६; ७; १३५, ७.

इर्यर्ते ८. ७, १३.

इर्यर्ति १. ५६, ४; २. ४२, १; ४. १७, १२; १३; २१, ५; ५. ३६, ४; ४२, १४; ९. ३०, २; ६८, ८; ८८, ५; १०. ३०, ९; ४५, ७.

इयर्ति १. ७, ८; ११३, १७; १६५, ४; ३. ८, ५; ४. ४५, १; ६. ३७, ४; ४४, १२; ४७, ३; ७. ६१, २; ६८, ३; ८. १२, ३१; ९. १४, ६; ६८, ९; ८४, ४; ८६, ४१; १०. २५, ११; ७५, ३; ११२, ५; १२३, २.

इर्यर्मि ३. ३४, २; ४. ४२, ५; १०. ६५, ३.

इयर्मि १. ११६, १; ३. १९, २; ८. १३, २६; १०. ४, १; १०४, ३; ११६, ९; १८८, २.

इयर्पि १०. १४०, २.

इयात् १०. १०१, ३; ११७, ४.

इयाते इर्ति ७. ३९, २.

इयानः १. ३०, १४; २. २०, ४; ३४, १४; ५. ६५, ३; ७. १७, ७; २९, १; ३८, ६; ६८, ३; ८. ५०, ५; ९६, १३; ९. ९२, ६; १०. २०, १०; ९९, ११; १२.

इयानं १. १८०, १०.

इयाना ७. ९१, २; ९५, ४.

इयानाः ७. २५, ५; ५२, ३; १०. ४७, ७; १०४, १.

इयानासः ५. २२, ३; १०. ६७, ८.

इयां ७. ८६, ४.

इयाम ५. ५३, १४.

इयाय ४. ४, ११. ७. ३३, १३; ९. ९४, ४; १०. ७३, १०^{२}.

इये २. १७, ७.

इयेथ ४. ९, १.

इरज्यत ८. ४०, ५.

इरज्यति १. ७, ९.

इरज्यति ८. ४१, ९.

इरज्यथः १. १५१, ६.

इरज्यन् १०. १४०, ४.

इरज्यंतं ७. २३, २.

इरज्यंते ८. ४६, १६.

इरज्यंता ६. ६०, १.

इरज्यवः १०. ९३, ३.

इरज्यसि १०. ७५, २.

इरज्यसि १. ५५, ३; ८. ३९, १०.

इरधंत १. १२९, २.

इरध्यै १. १३४, २.

इरस्यः ७. ४०, ६.

इरस्यति १०. १७४, २.

इरस्यसि १०. ८६, ३.

इरस्या ५. ४०, ७.

इरा ५. ८३, ४.

इराऽवत् ७. ४०, ५; ६७, १०.

इरावती इतीराऽवती ७. ९९, ३.

इराऽवतीः ५. ६९, २.

इराऽवतीं ५. ६३, ६.

इरिणं १. १८६, ९; ८. ४, ३; ८७, ४.

इरिणे ८. ८७, १; १०. ३४, १; ९.

इरी ५. ८७, ३.

इर्यैः ७. १३, ३; ८. ४१, ४.

इर्यै ५. ५८, ४; ६. ५४, ८.

इर्योऽइव १०. १०६, ४.

इलीबिशस्य १. ३३, १२.

इळः १. १२८, १^{२}; २. १०, १; ३. ४, ३; ५. ४२, १४; ६. १, २; ५८, ४; ७. ४७, १; १०. १७, ९; ७०, १; ९१, १; १९१, १.

इळयंत १. १९१, ६.

इळेया ३. ५३, १; ५४, २०; ५९, ३; ५. ४, ४; १०. ६४, ११.

इळां १. १३, ९; १४२, ९; २. १, ११; ३, ८; ३१, ४; ३. ४, ८; ७, ५; ५५, १३; ४. ५०, ८; ५. ४१, १९; ७. १६, ८; ८. ३१, ४; ९. ५, ८; १०. ३६, ५; ७०, ८; ११०, ८.

इळा १. १२८, ७; ३. २४, २; २७. १०.

इळांनां ९. १०८, १३.

इळांभिः १. ४८, १६; १८६, १; ५. ५३, २; ७. ३, ७; ६५, ४; ८. ३२, ९.

इळां १. ३१, ११; ४०, ४; ३. १, २३; ६. १०, ७; ५२, १६; ७. ४४, २; ६४, २; १०२, ३; ९. ६२, ३.

इळांयाः ३. २३, ४; २९, ३; ४; १०. १, ६; ९१, ४.

इळांऽवतीं ९. ९७, १७.

इळांऽवंतः १०. ९४, १०.

इळांऽवान् ४. २, ५.

इळांसु ५. ६२, ५; ६.

इळें १. १८८, ८.

इषंः १. ३, १; ९, ८; २७, ७; ३४, ३; ३६, ११; ४८, १५; ८६, ५; १२१, १५; १३०, ३[2]; १६५, १२; १६७, १; १८१, ६; १८६, ३; १८८, २; २. ६, ५; ३. १, २२; २, १०; ३, ७; १२, ५; २२, ४; ३०, १८; ५३, १; ५४, २२; ५८, ८; ५९, ९; ६२, १४; ५. ४, २; ६, ८; ७९, ८; ६. १, १२; १७, ३; ३५, ४; ३९, १; ५; ५२, १६; ६०, १२; ७. ५९, २; ९९, ६; ८. ५, ९; १०; २०; २१; ३१; ७, १९; २२, ९; २३, २९; २५, ६; ९. ३, १०; १३, ४; १५, ७; २३, ३; ३९, २; ४०, ४; ४२, ६; ४९, १; ६१, ३; ६२, २४; ६६, ४; १८; ७२, ९; ७४, २; ८७, ९; ९७, २५; १०८, २; ९; १०. २, ६; ५, ४; १७, ८; १३४, ३; १४०, ३; १४३, ६.

इषः १. १६३, ७; १७८, ४; ३. ३०, ११; ४. ३९, ४; ४०, २; ५५, ४; ५. ७, ३; १०; ६८, ५; ६. २४, ९; ६३, ७; ८. २३, ३; २५, ५; २६, ३; १७; ९. १४, ७; ७९, १; ९८, ५.

इषऽस्तुतः ५. ५०, ५.

इषणः ४. १६, ९; २२, १०.

इषणत् ४. १७, १४.

इषणंत १. १३४, ५; ४. २२, ९.

इषणयंत १०. ६७, ८.

इषणिं २. २, ९.

इषण्य ३. ५०, ३.

इषण्यत ५. ५२, १४.

इषण्यति ८. २२, ४.

इषण्यन् ३. ६१, ७; ९. ९६, ८.

इषण्यंति ५. ६, ६.

इषण्ययां ८. ६०, १८.

इषण्यसि १०. ९९, १.

इषध्यै ७. ४३, १.

इषंत १. १३४, ५.

इषं १. १२, ११; ४६, ६; ४७, ८; ६३, ८, ९२, ३; ९६, ८; १११, २; ११७, २१; १४०, १३; १६८, २; २. १९, ८; २२, ४; ३४, ७; ८; ४. १६, २१; ३२, ७; ४०, २; ५३, ७; ५. ६, १; ७, १; ३८, २; ४१, १८; ७०, २; ७६, ४; ८६, ६; ६. १४, १; ४७, ९; ४८, १३; ५०, १२; ६२, ४; ६३, ८; ६५, ३; ७. ५, ८; ७, ७; २४, ६; ३६, २; ४२, ६; ४८, ४; ६६, ९; ७०, ३; ७७, ५; ९६, ६; ८. १, १०; ६, २३; ७, १; ३; ८, १५; १३, २५; ३५, ४; ४३, १५; ५४, ७; ७०, ७; ७२, १६; ९३, २८; १००, ११; ९. ८, ९; २०, ४; ४१, ४; ६१, ६; १५; ६३, २; ६५, १३; २१; ६६, १९; ८६, १८; ३५; ९४, ५; १०१, ११; १०. ११, ७; २०, १०; ४०, ४; ४८, ८; ६१, ४; १२२, ६; १४०, ५; १६५, ५.

इषं १. १६५, १५; १६६, १५; १६७, ११; १६८, १०; १६९, ८; १७१, ६; १७३, १३; १७४, १०; १७५, ६; १७६, ६; १७७, ५; १७८, ५; १८०, १०; १८१, ९; १८२, ८; १८३, ६; १८४, ६; १८५, ११; १८६, ११; १८९, ८; १९०, ८.

इषऽयुते ६. १६, २५.

इषयध्यै १. १८३, ३; ६. ६४, ४.

इषयंन् ६. १, २; ९. ८४, ३; १०. ९१, १.

इषयंत १. ७७, ४; २. २, ११; ७. ८७, ३.

इषयंतः ५. ४९, ४; ६. १६, २७.

इषयंतं ६. १, ८; १८, ५.

इषयंता ८. ५, ५.

इषयंती इति ४. ५६, ४.

इषयंतीः ३. ३३, १२.

इषयंतौ ८. २६, ३.

इषऽयुः १. १२०, ५.

इषयें ६. ५२, १५.

इषयेम १. १८५, ९.

इषंवः २. २४, ८; ६. ७५, ११; १०. १०३, ११.

इषऽवान् १. १२९, ६.

इषा १. ३०, १७; ५३, ४; ५; ८८, १; ११२, १८; ११७, १; १०; १२९, ७; १६५, १५; १६६, १५; १६७, ११; १६८, १०; १८५, ९; ६. २०, ६; ६८, ५; ६९, १; ७. ६४, ३; ६८, ९; ८. ५, ३४; ३६; २०, २; २२, १२; ८२, ३; ९२, १०; १०. ८२, २; १०६, ५.

इषां १. १६८, ५; १८१, १; ३. २३, २; ६. ४७, ९; ६०, १३; ७. ६९, १; ८. ४६, २; ७१, १३.

इषितः १. ३, ५; ३. ३, २; ४, ३; ३२, ४; १६; ३३, ११; ६०, ५; ६. ५, ६; ११, १; ७. ३९, १; ९. ३७, ६; ७७, २; १०. ११, ४; ८८, ३; ९१, ७; ९८, १०; ११०, ३; ९; १६५, १; २.

इषितत्वता १०. १३२, २.

इषितं २. ३८, ५; ८. १, २१.

इषिता ३. १२, १; ७. ३३, १३; १०. १०८, २.

इषिताः १. १८२, ६; ३. ४२, ३; ६२, १२.
इषितासः ६. ४९, १०.
इषिध्रः ६. ६३, ७.
इषिर १. १२९, १.
इषिरः ३. ५, ४; ५. ४१, १२; ६. २९, ३; ७. ३५, ४; ९७, ७.
इषिरं ३. २, १४; ५. ३७, २; ६८, ४; ९. ९६, १५.
इषिरस्य ८. ९८, ९.
इषिरा ५. ७५, ५.
इषिराः २. २९, १.
इषिराः ३. ५६, ८; १०. ६८, ३; ९४, ५.
इषिरां १. १६८, ९; ३. ३०, ९; ५. ३७, ३; ९. ८४, ४; १०. ९८, ३.
इषिराय १. १२८, ५; ८. ४६, २९.
इषिरासः ९. ७३, ७.
इषिरेण ८. ४८, ७.
इषिरेभिः ३. ६०, ७; १०. ७३, ५.
इषिरैः ६. ६२, ३.
इषुः ८. ७७, ७; ९. ६९, १; १०. ९५, ३.
इषुकृताऽइव १. १८४, ३.
इषुऽधिः ६. ७५, ५.
इषुऽधीन् १. ३३, ३.
इषुऽधेः १०. ९५, ३.
इषुध्यति ५. ५०, १.
इषुध्यते १. १२८, ६.
इषुध्यवः ५. ४१, ६.
इषुध्यसि ८. ६९, २.
इषुध्याऽइव १. १२२, १.
इषुऽबलाः ६. ७५, ९.
इषुं १. ३९, १०; ६४, १०.
इषुऽमंतः ५. ५७, २.
इषुऽमान् २. ४२, २.
इषुऽयुते १. १२८, ४.
इषुंऽहस्तेन १०. १०३, २.
इषुंऽहस्तैः १०. १०३, ३.
इषूः १०. ८७, ४.
इषे १. ५४, ११; ७१, ८; १२०,९; १२१, १४; १८०, २; ६. १३, २; १७, १४; ६८, १; ७. २०, १०; ८. २०, ८; ९३, ३४; ९. ६४, १३; ६५, ३; १०. ४८, ९; ५०, ३.
इषे ४. २३, ६; ६. २२, ५; ८. ४६, १७; १०. २०, ७.
इषेम ८. ४४, २७.
इष्कर्तं १०. ४८, ८.
इष्कर्त ८. २०, २६.
इष्कर्ता ८. १, १२.
इष्कर्तारं ८. ९९, ८; १०. १४०, ५.
इष्कृणुध्वं १०. ५३, ७; १०१, २.
इष्कृतऽआहावं १०. १०१, ६.
इष्कृतासः ७. ७६, २.
इष्कृतिः १०. ९७, ९.
इष्टऽअश्वः १. १२२, १३.
इष्टनिः १. १२७, ६.
इष्टं १. १६२, १५.
इष्टयः १. १४५, १; ६. ७४, १.
इष्टऽयामा ९. ८८, ३.
इष्टये १. ३०,१२; ५७,२; ११२, १;२; ११३, ५; ६; १२९, ४; ५. ४४, ४; ७२, ३; ७४, ३; ७८, ३; ६. ७०, ४; ७. ९२, ३; ८. ३८, ४; ९. ९७, ४२; १०. ३६, ६; ४९, ९; ७०, ११; ९२, १३; ११५, ४.
इष्टऽरश्मिः १. १२२, १३.
इष्टऽव्रताः ३. ५९, ९.
इष्टस्य १०. ११, २.
इष्टाः ८. ९३, २३.
इष्टानि १. १६४, १५; १०. ८२, २.
इष्टापूर्तेन १०. १४, ८.
इष्टिः ४. ४, ७.
इष्टिऽभिः २. १, ९; १८, १.
इष्टिं १. १६६, १४.
इष्टिषु १०. १४७, २.
इष्टीः ७. ९३, ८.
इष्टे १. १४३, ८; ६. ८, ७.
इष्टेः १. १२५, ३.
इष्टैः ४. ५५, ६.
इष्टौ १. ६२, ३; १४८, ३; २. २८, ७; ४. ६, ७; ६. ११, ३; १०. ४४, ९.
इष्ट्वा १०. १६९, २.
इष्णात् १०. ६१, ५.
इष्णन् १. १८१, ६; २. २०, ५; ४. १७, ३; ९. १७, ५.
इष्णानः १. ६१, १३.
इष्णासि १. ६३, २.
इष्मिणः १. ८७, ६; ५. ८७, ५; ७. ५६, ११.
इष्मिणं ५. ५२, १६.
इष्यत १. १५, ९.
इष्यति १. ३४, १०.
इष्यति ९. १२, ६; ३०, १; ३५, ४; १०. ११, ६.
इष्यते ९. ६९, १.
इष्यन् १. ६१, १२; ९. ९५, ५.
इष्यसि ९. ६४, ९; २५.
इष्यामि ८. ९६, १४.
इष्ये ४. ३३, १.
इष्वाः १०. १८, १५.
इष्वै ६. ७५, १५.
इह १. १, २; १२, ३; १०; १३, ३; १०; १४, ९; १२; १६, २; २१, १; ४; २२, १; ९; १०; १२;२४, ११; २८, ५; ३४, ११; ३५, १; ६; ३६, २; १०; ३८, १५; ४२, ७–९; ४४, ७; ४५, १; ९; ७४, ६; ७६, २; ४; ८९, ७; ९२, १४; १८; ९४, १६; १०६, ४; ११०, १; ११३, ७; १२; १२१, ८; १३४, १; १३५, ५; ६; १४२, ४; १६१, ३; १६४, ७; १८; ४९; १७७, ४; १८१, २; १८३, ६; १८४, ६; १८५, ११; १८६, ६; १८८, ६; १९१, ७; २. ३३, १५; ३५, १३; ३६, ४; ३७, ५; ४१, ४; २१; ४२, २; ३. २, ५; ३, ५; ७, ९; ८, १; ९, २; १२, ३; १४, ७; १९, ५; २०, ५; २५, १; २; ४; २८, ४; २९, १६; ३०,९; ३२, १; ३५, ३; ३७, ११; ४१, ८; ४२, ४; ४७, ५; ५०, २;५१, ७; ८; ५२, ५; ५४, ५; ५७, ५; ६०, ६; ७; ४. २, २; ४, ९; ५, १४; ७, १; १४, ४; १६, १;

२१, १; २; ३१, ११; ३५, १; २; ३६, ९[२]; ४६, ५; ७[२]; ५६, १; ५. १, ११; २, ७; ५, ९; ४०, ७; ५६, ७; ६०, १; ७३, २; ७४, ६; ७५, ७; ७६, १; २; ६. ९, २; १६, २४; १९, ४; २८, १; ४७, २; १९; ४९, १; ५४, ९; ५८, १; ५९, ३; ९; ७४, ४; ७. १, ८; ९: ११, १; ३; ५; १७, २; ३२, १; ३५, ६; ४१, ५; ४२, ५; ४९, १; ५०, १; ५६, ९; ५९, ६; ८. २, २७; ५, ३३; ८, ४; ९; १३, २७; २६, ९; ३०, ४; ३४, २; ४; ११; ३५, ३; ४; ३९, ९; ४४, ३; ९; २३; ४५, १७; २४; ४७, १२; ६२, ४; ६६, ७; ६९, ११; ७२, ५; ७३, १०; ९९, १; १००, ४; ७; १०२, १०; ९. ४९, २; ६२, १५; ६७, २१; ८५, १; १०. १, ६; ७; २, १; ३, ७; ९, २; १०, ६; ८; ११, ९; १४, ५; १२; १५, ३; ५; ७; ११; १३[२]; १६, ९; १८, ६; ९; १९, ३[२]; २२, २; ३८, ५; ५२, १; ५८, १; ५९, ६; ६१, १९; ६३, २; ६९, ३; ७०, २; ३; ८१, ६; ८४, ५; ८५, २७; ४२; ८७, ८; ९०, ४; ९८, १२; १००, १; १०१, ३; ९; १२; १०४, २; ३; १०६, ११; १०८, ८; ११०, ८; ९; ११४, ७; ११९, ९[२]; १२८, ५; १३०, ५; १३७, ५; १४१, १; ४; १५१, ५; १६०, १; २; १६५, ३; १६७, २; १६९, २; १७३, २[२]; १७८, १; १८०, १; १८३, १[२].

इहऽइव १. ३७, ३; ८. ५, १.

इहऽइह १. १८१, ४; ३. ६०, १; ४. ४३, ७; ५. ३०, १०; ४७, ५; ७. ५९, ११; १०. १३१, २.

इहि ८. ३२, २२[२].

इहि १. ४, ४; ९, १; १०, ४; ७१, १०; ७६, २; ८०, ३[२]; १०४, ९; ३. ३५, ६; ४५, १; ५. १६, ५; ३५, ८; ७८, ८; ८३, ६; ६. १६, १६; ५४, ६; ५५, १; ८. ४, ८; १२; १७, ९; ११; ३२, २१; ५३, ५; ६१, ७; ६४, ४[२]; १०; १२; ६५, ५; ९. ६४, १३; ९७, ३३; १०७, १९; १०. १४, ७[२]; ८; १०; १८, १; ८; ३०, ५; ३३, ७; ३७, ९; ५१, ५; ५३, ६; ६०, ७[२]; ८३, ३; ५–७; ८४, ३; ८६, २०; ९५, २; १३; ९८, १; १०३, १२[२]; १२४, १; ५; १५५, २; १६४, १.

इहेहऽमातरा ६. ५९, २.

इहो इतिं ९. ६५, ५.

ई

ईक्षयंत् १. १३२, ५.

ईक्षे ४. २०, ८; ६. १९, १०; ८. ७९, ९.

ईक्षेण्यांसः ९. ७७, ३.

ईखय ९. ५२, ३[२].

ईखयंति १. १९, ७.

ईखयंतीः १०. १५३, १.

ईखयावहै ७. ८८, ३.

ईखितं १०. १४३, ५.

ईजते ५. ४८, २; ६. ६४, ३.

ईजानः ४. ५१, ७; ७. ५९, २; ८. २४, ३०.

ईजानं १. १२५, ४; १०. १३२, १[२].

ईजानस्य ६. ४८, २०.

ईजानाय १. ११३, २०.

ईजिरे १०. ६६, ७.

ईजे ६. ३, २; १६, ४.

ईजे ६. १, ९.

ईट्टे १. १८०, २; ३. ५२, ५; ५. १२, ७; ७. ९३, ४; ८. १०३, १३.

ईट्टे १. ८४, १८; १३४, ५; ४. २५, १; ३; ७. २४, ५; ९१, २; १०. १०४, १०.

ईड्यः १. १, २; १२, ३; ७५, ४; १८८, ३; २. १, ४; ३. २, २; ५, ९; २७, ४; २९, २; ४. ७, १; २४, २; ५. २२, १; ६. १, २; १३, १; ७. १५, १०; ८. ११, १; १०; ३४, ८; ६०, ३; ९. ६६, १; १०. १००, ९; ११०, ३.

ईड्यं ३. ५, ६; ९, ८; १७, ४; २९, ७; ४. ७, २; ६. १५, २; ८; ४९, २; ८. २३, २०; ४४, ७; ७४, ५; १०. ३०, ८.

ईड्यस्य १०. २, ४.

ईड्याः १. १४, ८.

ईड्यान् १०. ५३, २.

ईड्याय ३. ५४, १.

ईदृशे १. १७, १; ४. ५७, १; ६. ४५, ५.

ईधिरे ५. २५, २.

ईधिरे ३. २९, १५; ५. ८, १; ७; ११, २; १०. ११८, ९; १५०, ४.

ईधे १. ३६, ११.

ईधे ६. १६, १४; १५; ७. ३६, १; ८. १०२, २२; १०. ४५, ३.

ईं १. ४, ७; ९, २; ३६, ७; ३८, ११; ५१, २; ५२, ६; ५४, १०; ६५, २; ३; ६७, २; ४; ७१, ४[२]; ५; ७९, ३; ८१, १; ८५, ११; ८७, ५; ११६, १२; १२२, ९; १२७, ७; १०; १२९, ७; ८; १३४, २; १४१, १; ३[२]; १४४, २–५; १४५, ४; ५; १४८, १; ५; १५१, ३; १५५, ३; १५८, ५; १६२, १२; १६४, ७; १०; १६; ३२[२]; १६७, ५; ७; ८[२]; १७१, २; १८६, ६; ७[२]; ८; २. ५, ३; १२, ५; १३, २; १४, १०; १५, ५; १६, २; २२, १; २; २६, ४; ३०, ३; ३५, १; १३[२]; ३. ९, ४; ३०, १६; ३५, ३; ३६, ६; ४. ७, ५; ८, ५; ९, १; १७, ४; १४; १७; २१, ७[२]; २७, २; ४; ४१, ९; ५. १, ३; ४; २, ५; ७, ५; ९, ५; २९, २; ३०, १०; ११; ३२, ५; ७; ३४, २; ७; ८; ३७, ३; ३८, २; ४४, १२; ४७, ४; ५; ५४, ४; ६१, ११; ७४, ४; ६. ३, ६[२]; ९, ३; १७, २; २०, ९; ४२, २; ४७, १५; ५०, ४; ५३, ५; ६२, ९; ७. १, १८; २०,

३; २१, १; २६, २; ३२, १७; ४०, ३; ५६, १; २१; ६०, ३; ६६, १४; ६८, ७; ८८, १; १०३, ३; ८. १, १७; २, ६; १७; १७, ११; १९, २; ३२, ११; ३३, ७; ४५, ३९; ४७, १; ४९, ४; ५०, २; ३; ६४, १२; ७४, १५; ७७, २; ७९, २; ६^{२}; ८३, ५; ९७, ११^{२}; १००, ३; ९. १, ७; ८; ७, ५; ३२, २; ३; ३४, ५; ६२, ६; ७४, ७; ७७, १; ७८, ३; ८१, १; ८६, १७; ८८, २^{२}; ८९, २^{२}; ४; ५^{२}; ९२, २; ९७, २२; १०७, १३; ११०, ६; १०. १, ४; १०, ६; ११, ३; १६, १; २७, ११^{२}; ३०, ६; ३१, ४; ८; ३२, ८; ४०, १४; ४४, ३; ४५, ४; ६१, ८; ६७, ५; ७; ६९, १; ७१, ६; ७४, ६; ७६, ३; ९४, ३; ९५, ७; १८; १०१, १०; १०६, १; १२४, ८^{२}; १२५, ४; १३३, ४.

ईमहे १. ६, १०; १३६, ४^{२}; ५. ५३, १३; ७. १६, ४; ५४, १; ९४, ९; ८. १३, ५; २३; १८, ३; ४५, १४; १०. ३६, १०; १२६, ७.

ईमहे १. १०, ६; १७, ३; २४, ३; १४; ३६, १; ४०, १; ४२, १०; ४३, ४; १०५, १५; १०६, ४; ५; १३८, ३; २. ३२, २; ३४, ११; ३. २, १३–१५; २६, ५; ६; २७, ४; ३७, ३; ६; ४२, ६; ६२, ११; ४. ३२, १७; ५. ५, ६; २४, ४; २६, २; ६३, २; ८२, ३; ६. १, ७; १५, ७; २२, ३; ५३, ९; ५४, ८; ५५, २; ५६, ६; ७. ७, ७; ५८, ५; ८१, ४; ८. ५, २७; १२, १–३; १३, २४; १८, २०; २१, ८; २२; १३; २४, २६; २६, २२; ३३, ३; ४३, १२; ३१; ३३; ४४, १०; ४६, ६^{२}; ४९, ९; ५३, १; ६०, २; ६८, १०; ७१, १३; ७५, १६; ८८, २; ९०, ६; ९८, ११; ९९, २; ९. २, ८; ४८, १; ६६, २०; ७४, १; १०. २४, २; ३५, २; ३; ९; ६१, २४; ६५, १०; ६६, १३; १६७, २.

ईमिर्ति १. १०३, १; १४०, २; ३. ३६, ८; ९. ४५, ५; ६३, १७; ७१, ५; ६; ७२, ६; १०२, ६; १०४, २; १०७, १७.

ईयऽचक्षसा ५. ६६, ६.

ईयतुः ८. ६८, ३.

ईयतुः ३. २, ९; ८. ९९, ६.

ईयंते १. ३०, १८; १४४, २; ५. १८, ३; १०. ९६, ७.

ईयते १. ३०, १९; ३५, ९; ४८, ५; १४१, ८; १४५, १^{२}; १६०, १; १६१, १; १९०, ४; २. १३, ३; ३. ३, २; ६; ४. ८, ४; १४, ३; ३१, १४; ४५, ६; ५. ३४, १; ६. २१, १; ३, ४; ४७, १८; ५८, २; ५९, ५; ७. ३२, ५; ८२, ५; ८. २२, ४; ९. ५, ४; १५, ५; ६५, १६; ८६, ४२; १०. ४६, ६; १६८, २.

ईयथुः ५. ७३, ४.

ईयंते ५. ५५, १.

ईयमानः १०. १६८, ३.

ईयमानं ५. ३०, १.

ईयमानाः ५. ४७, २.

ईयसे १. १३३, ६; २. ६, ७; ३७, ३; ५. ३, ८; ७. ३, ३; १०. ७५, ६; १३७, ३.

ईयसे ४. २, २; ३; ७, ८; ५. ८१, ४; ६. १५, ९; ९. ८६, ३७; ११०, १.

ईयिऽवांसं ३. ९, ४.

ईयुः १. ११३, ११; ३. ५८, ८; ७. १८, ९; १०; १०. १५, १; २.

ईयुः १. २४, १०; ३३, ४; १६३, ८; १६४, ८; २. २४, ६; ८. १०१, १४; १०. ६१, २१; १०७, ८.

ईयुषीणां १. ११३, १५; १२४, २.

ईरतां १. १२३, ६; ४. ८, ७; १०. १५, १.

ईरते १. ५२, १; ८१, ३; १०. ३७, ९; ९९, ४.

ईरते १. १४०, ५; १८७, ५; ४. ४५, २; ५. २५, ७; ६३, ४; ८३, ३; ७. ५६, १४; ८. ३, १५; ७, ७; १७; ४३, १; ४४, ४; १७; २५; ९. ३३, ४; ५०, १; २; ६९, ६; ८५, ७; ९५, ३; १०. ९७, ८; १६८, २.

ईरय १. ४८, २; ५. ४२, ३; ८. ९६, १०; ११; ९. ९६, ८; १०२, ३; १०. ११, ६; २९, ५; ४९, १०; ९८, ८; १२२, २; १८७, १.

ईरयत् ८. ७९, ६.

ईरयतं १०. ३९, २.

ईरयंति ९. ७२, १.

ईरयति ९. ९७, ३४.

ईरयथ ५. ५५, ५.

ईरयध्यै ४. २, १.

ईरयध्वं ४. ३४, २.

ईरयन् ९. ६२, २६; ७६, २; ९७, १४; ५६; १०. ६५, २.

ईरयंत ८. ७, ३.

ईरयंति ५. २०, २.

ईरयंती १. ११३, १२; ३. ६१, २; ७. ७९, ५.

ईरयं १०. ८९, ४; ११६, ९.

ईरयस्व ७. ५, ८; १०. ८५, ३७.

ईरयाम १०. १११, १.

ईरयामहे ७. ९४, ४.

ईरयामि २. ३३, ८.

ईरयाव ७. ८८, ३.

ईरयेथे इति १०. १०६, १०.

ईराथां ८. ७३, १.

ईरिरे ३. ११, ९; २९, १५; ६०, ३; ६. ५, २.

ईर्ते ९. ९१, ३.

ईर्ध्वे १. ११३, १६.

ईर्मऽअंतासः १. १६३, १०.

ईर्मा ४. २७, २; ५. ६२, २; ७३, ३; ८. २२, ४; १०. ४४, ६.

ईर्ष्वे १०. १८, ८; ८५, २१.

ईळत १. ९६, ३.

ईळते १. १४, ५; ३६, १; ३. ६, ३; ५. १४, ३; ६. २, २; ७. ९४, ५; ८. ७४, ६; १२; १०. ३०, ४.

ईळते १. १५, ७; १२८, ८; ३. १०, २; १३, २; २७, १४; ५. १, ७; ८, ३; ९, १; १४, २; २१, ३; ६. १४, २; १६, ७; ७०, ४; ७. ८, १; १०, ५; ११, २; ४५, ४; ७६, ६; ८. २३, २५; ४३, २०; ६०, १६; १०. २१, ६; ७०, ३; ८०, ६; ८३, २; १२२, ४.

ईळा ८. ३९, १.

ईळानया ८. १०२, २.

ईळाना ५. २८, १.

ईळानाः १०. ६६, १४.

ईळानाय २. ६, ६.

ईळामहे १०. ८५, २२.

ईळामहे १०. ५३, २.

ईळितः १. १३, ४; १३९, ७; १४२, ४; २. ३, ३; ७. ७, ३; १०. १५, १२; ६९, ४; ८४, ४.

ईळिता ५. ५, ७; १०. २४, ४.

ईळिष्व ८. २३, १.

ईळिष्व ६. ६०, १०; ८. १९, २; ७१, १४.

ईळीत ५. १७, १; २१, ४; ६. १६, ४६.

ईळे १. ११२, १; ३. १, १५^{२}; २७, २; ५. ६०, १; ६९, ३; ८. १९, २१.

ईळे ४. ३, ३.

ईळे १. १, १; ४४, ४; ३. २७, १२; ५५, १२; ४. ३, ९; ३३, १; ५५, ३; ६. १६, ४; ७. ५३, १; ८. ३१, १४; ४३, २४; १०. २०, २; ३५, १०; ८५, २१.

ईळेन्यः १. ७९, ५; १४६, ५; ३. २७, १३; ५. १, ९; ७. ९, ४; ९. ५, ३; १०. ११८, ३.

ईळेन्यं ५. १४, ५; ७. २, ३; १०. ४६, ९.

ईवत् ५. ४९, ५; ८. ४६, २१.

ईवतः ४. १५, ५; ४२, ३; ७. २३, १; ५६, १८.

ईवते ४. ४, ६; ६. ७३, २.

ईशत १. २३, ९; ३६, १६; २. ७, २; २३, १०; ४२, ३; ६. ७१, ३; ८. ४८, १४; ९. ८५, ८; १०. २५, ७; ३६, २.

ईशते ७. ६६, ६; ८. ४७, ४; १०. ४३, ३.

ईशाथे इति ७. ९७, १०.

ईशानः १. ५, १०; ७, ८; ६१, ६; १२; १५; ७९, ४; ८४, ७; १७५, ४; २. २४, १५; ४. १६, ११; ७. १, १६; १५, ११; ८. ६, ४१; १७, ९; ४०, ५; ९. ६१, ६; १०१, ५; १०. ७३, ८; ९०, २.

ईशानः १. ८७, ४; १३०, ९; ९. ८६, ३७.

ईशानऽकृत् १. ६१, ११; २. १७, ४; ६. १८, ६; ८. ५२, ५; ६५, ५; ९०, २.

ईशानऽकृतः १. ६४, ५.

ईशानं १. ५, २; ११, ८; २४, ३; ८९, ५; ६. ५४, ८; ५५, २; ७. ६, ४; २१, ८; ३२, २२^{२}; ८. १, २०; २६, २२; ३२, १४; ४६, ६; ५३, १; ६८, ६; ७६, १; ८१, ४.

ईशानं ७. ७, ७; ९. ६२, २९.

ईशानयोः ७. ९०, ५.

ईशाना १. ११३, ७.

ईशाना ५. ७१, २; ७. ८२, ४; ९४, २; ९. १९, २.

ईशानाः १०. ९, ५.

ईशानात् २. ३३, ९.

ईशानाय ७. ९०, २.

ईशानासः ७. ८३, ५.

ईशानासः १. ७३, ९; १२२, १३; १२९, २; १४१, ३; ७. १, १७; ९०, ६; १०. ६३, १७.

ईशिरे १०. ६३, ८.

ईशिरे ५. ५८, १; १०. ५६, ४.

ईशिषे १. ९१, २३; २. २४, १; ३६, १; ४. ३२, ७; ६. ४१, ३; ८. ४४, १८.

ईशिषे १. १७०, ५; २. १, ६; ७; १०; १३, ६; १६, ६; ४. ५२, ३; ५. ८१, ५; ८. ३७, ५; ६४, ३; ७१, ८; ८२, ७; १०. ४४, ५.

ईशीत ४. १५, ५; ८. २३, १५.

ईशीय ७. ३२, १८; ८. १४, १; १०. ३३, ८.

ईशे ३. १६, १^{२}; १८, ३; ४. २१, ४; ६. १८, ११; ७. ४, ६^{२}; ३७, ७; १०१, २; ८. २५, २०^{२}; ६८, ७; ७१, २; १३; ९. ७४, ३; १०. ६, ३^{२}; १२१, ३; १८५, २.

ईशे १. ७१, ९; १००, ७; १२७, ७; १६५, १०; ३. १६, १; ५१, ४; ४. १२, ३; ५५, ८; ६. ५१, ८; ७. ७५, ५; १०. ८६, १६^{२}; ८९, १०.

ईषति ९. ७१, ६.

ईषते १. ३९, ८; १२४, ६.

ईषते १. ८४, १७; १४१, ८; १४९, १; ५. ३४, ४^{२}; ६७, ५^{२}; ८३, २; ८६, ३; ६. ४२, ३; ८. ४५, ३७; ७८, ९.

ईषथुः १. ११२, १६.

ईषंत ८. ९६, ३.

ईषंते ६. ६६, ४.

ईषमाणः १. १७१, ४.

ईषमाणाः ४. ५८, ६; ८. ९६, ७.

ईषा ३. ५३, १७; ८. ५, २९.

ईषुः ३. १, २.

ईषे १०. ८९, ३.

ईषे १. १८६, ४; ५. ४९, १.

ईष्टे ५. ८७, ३.

उ

उक्तः ४. ४१, १.

उक्तं १०. २७, १०; १२५, ४.

उक्थऽअर्का ६. ३४, १.

उक्थऽभृतं ७. ३३, १४.

उक्थं १. ८, १०; १०, ५; ८६, ४; १००, १४; १७; १४०, १३; ३. ५३, ३; ४. ६, ११; १६, २; ४९, १; ५. ३९, ५; ६. १८, १५; २६, ५; ७. २६, १; ३१, २; ८. २, १४; ६६, ५; ९. ४७, ३; १०. ६७, १; १३०, २.

उक्थऽवर्धनः ८. १४, ११.

उक्थऽवाहः १०. १०४, २.

उक्थऽवाहसः ८. १२, १३.
उक्थऽवाहसा ६. ५९, १०.
उक्थऽवाहसे ८. ९६, ११.
उक्थऽशंसिनः ६. ४५, ६.
उक्थऽशंसिनं ८. १०३, ४.
उक्थऽशासः ४. २, १६; १०. ८२, ७.
उक्थऽशासं १०. १०७, ६.
उक्थऽशासा २. ३९, १.
उक्थऽशासः ७. १९, ९.
उक्थऽशुष्माः ६. ३६, ३.
उक्थऽशुष्मान् १०. ६३, ३.
उक्थस्य ६. ४४, ६.
उक्था १. ५, ८; ५४, ७; ८०, १६; १६५, ४; १७३, ९; ४. ३, ४; ११, ३; २२, १; ३३, १०; ४२, ६; ५. १८, ४; ३३, ४; ६. २३, ५; २४, १; २९, ४; ३८, ४; ६५, ४; ६७, १०; ७. १९, ९; ८. १, १; २, ३०; ३३, १३; ५२, ३; ६३, २; ९३, २७; १०. ११४, ८.
उक्थानि १. ८४, ५; २. ८, ५; ७. ५६, २३; ८. ६, ३५; १३, १९; १६, २; ३२, १७; ८२, ४; ९५, ६; ९. १११, ३; १०. ४४, ८.
उक्थाय ५. ४५, ३.
उक्थिनः ३. १२, ५; ८. १५, ६; ३३, २; ५३, ६; ७६, ८; १०. ४८, ४.
उक्थिनं ३. ५२, १.
उक्थे ४. २०, १०; ६. २३, १; ८. १२, १८; २७, १; ३२, ६; ६४, ९.
उक्थेऽउक्थे ७. २६, २; १०. ४५, १०.
उक्थेन ८. ६, २१; ४३; १०. १००, ५.
उक्थेभिः १. २, २; ४७, १०; २. ११, १६; ३. ३४, ७; ४२, ४; ५. ४५, ४; ६. १०, १; २४, ६; ७. ९४, ११; ८. २, १६; ५१, ३; ९. २४, ६; १०. ६४, १६; ११२, १.
उक्थेषु २. ११, ३; ३. १३, ६; ३३, ८; ४१, ४; ४. ३०, १६; ५. ६, ९; ८. ३४, ११; ४५, २९; ९२, १२; १०. ७२, १.
उक्थैः १. २७, १२; ६१, १३; ७१, २; १३०, १०; १३६, ५; १८४, १; २. ११, २; ३. ५; २; २०, १; ५१, ४; ४. ३, १६; ४, ७; १६, १५; २१, ५; ५१, ७; ५. ४, ७; ४२, ९; ४५, १; ६. १, १०; ५, ५; १०, ३; १३, ४; २४, १; ७; ६९, ३; ७. ३४, १६; ५६, १८; ८. ९, ९; ६२, १; ९५, ७; ९. १७, ४; १०. २४, २; २८, १२; ६१, १७; २६; ८०, ५; ८८, ५; १३०, ४.
उक्थ्यः १. १७, ५; ७९, १२; ८३, ६; २. १३, २–१२; ३. १०, ६; ४. ३६, १; ५. २६, ६; ९. ८६, ४८.
उक्थ्यं १. ३८, १४; ४०, ५; ४८, १२; ५२, ९; ६४, १४; ८३, ३; १०५, १२; १३; १३६, २; २. १३, १; २३, १४; ३२, ४; ३. २, १३; १५; २६, २; ५१, १; ४. ३६, ४; ५३, २; ८. १३, १; ६६, २; ६७, ३; ९. १९, १; २९, २; ३; ४०, ६; ४८, २; ६१, १५; ११०, ८; १०. ११, ५; ४१, १; ४८, ९; ९६, ५; १४०, १.
उक्थ्या ८. ९९, २.
उक्थ्या ८. ९, २१.
उक्षऽअन्नाय ८. ४३, ११.
उक्षणः १. ६४, २; १०५, १०; १३५, ९[२]; १६८, २; ३. ७, ७; ५. २७, ५; ५२, ३; ६. १६, ४७; ८. १, ३३; ५५, २; १०. ८६, १३; ९१, १४.
उक्षणि ९. ८५, १०; ८६, ४३; ९५, ४; १०. १२२, ४.
उक्षण्यतः ८. २६, ९.
उक्षण्यायने ८. २५, २२.
उक्षण्युः ८. २३, १६.
उक्षत १. ८७, २.
उक्षतं १. १५७, २; ३. ६२, १६; ५. ६३, ५; ७. ६२, ५; ६५, ४; ८. ५, ६.
उक्षते १०. ९२, ५.
उक्षन् ४. १, १०.
उक्षंतं १. ११४, ७.
उक्षंति १. १६६, ३.
उक्षंते २. ३४, ३; ५. ५९, १.
उक्षऽभिः १. १३९, १०[२]; २. ७, ५; ६. ६४, ५; ७. ७९, १.
उक्षमाणः ५. ४२, १४.
उक्षमाणं २. २, ४; ९. ९९, ५.
उक्षमाणाः ४. ४२, ४; ५. ५७, ८; ६. ६६, ४.
उक्षमाणे इति ४. ५६, २.
उक्षयंत ६. १७, ४.
उक्षा १. १४६, २; ३. ७, ६; ४.५६, १; ५. ४७, ३; ९. ६९, ४; ८३, ३; ८९, ३; १०. ३१, ८.
उक्षाऽइव ९. ७१, ९.
उक्षाणं १. १६४, ४३.
उक्षितः १. ३६, १९; २. २१, ३; ५. ८, ७; ९. ७२, ७.
उक्षितं १. ११४, ७; २. १६, १.
उक्षिताः ५. ५५, ३.
उक्षितासः १. ८५, २.
उक्षिते इति २. ३, ६.
उक्षेथां ७. ६४, ४.
उक्ष्णः ८. ७, २६; १०. २८, ११; ८६, १४.
उखऽछित् ४. १९, ९.
उखा १. १६२, १५; ३. ५३, २२.
उखायाः १. १६२, १३.
उग्रं ८. २४, ७; ४६, २०.
उग्र १. ३३, ५; १२९, ५; ३. ४६, २; ४. २, १८; २०, ७; २४, ४; ५. ३२, २; ६. १७, १; १०;२३, ८; २५, १; ३७, १; ४१, ३;५३, ४; ७. २२, ८; २५, १; ४; २८, २; ८. ६, १४; १८; ३३, १०; ३७, २; १०. ११३, ३.
उग्रः १. ७, ४; ५१, ११; ५५, ३; १००, १२; १२७, ११; १३०,७; १५२, २; १६५, ६; १०; १७१, ५; १७९, ६; २. २३, १२; ३३, ९; ३. ३०, ३; ३६, ५; ४८, ४; ४. १६, २०; २०, १; ६; २२, २; २३, ७; ५. ३२, ८; ७३, ७;

६. १८, ६; २३, ३; ७. २०, १; ३४, १०; ३८, ६; ४०, ३; ५६, २३; ८२, ५; ८. १, २७; ३, १७; २१, २; २९, ५; ३२, २; ३३, ९; ४९, ७; ५२, ५[२]; ६५, ५; ९. १०९, २२; १०. २९, ३; ४२, ७; ७३, १; ९७, १२; १०३, ५; १०९, १; ११३, ६; १२०, १.

उग्रःऽई॑व ६. १६, ३९.

उग्रऽदे॑वं १. ३६, १८.

उग्रऽध॑न्वा १०. १०३, ३.

उग्र॑ऽपुत्रे ८. ६७, ११.

उग्रऽबा॑हवः ८. २०, १२.

उग्रऽबा॑हुः ८. ६१, १०.

उग्रं १. ८४, ९; १०२, १०; ११६, १२; ११८, ९; १२९, १०; २. ३३, ११; ३. २६, ५; ३०, २२; ३६, ४; ४६, ४; ४७, ५; ४. ३८, १; ५. ३०, २; ३१, ८; ३५, ६; ६. १७, १३; १८, १; ४; १९, ६; २६, १; ३८, ५; ४६, ६; ४७, १५; ५१, ८; ७. ३३, २; ४१, २; ५६, ७; ८. १, २१; २०, ३; ४९, ६; ५०, ६; ६१, १२; ६८, ६; ७०, ४; ९७, १०; १३; ९. ६१, १०; ६२, २९; ९७, २१; १०. २८, ७; ४४, ३; ४७, ३; ८४, ३; १०३, ९; १२५, ५; १२६, ५; १२८, ९.

उग्रंऽउ॑ग्रं ६. ४७, १६.

उग्रस्य॑ २. २३, ११; ३. ४३, १; ५. २०, २; ६. १८, ४; ८. ४, ७; १०. ३४, ८.

उग्रा १. २१, ४; ५. ६३, ३; ६. ६०, ५; १०. १२१, ५; १५९, २.

उग्रा १. १५७, ६; ४. ४१, ४; ६. ६२, ३; ७२, ५; १०. १०६, ७.

उग्राऽई॑व १०. १०६, ४.

उग्राः १. १९, ४; २३, १०; १३४, ५; ६. ६६, ६; ११; ७. ३४, ३; ५६, ६; ५७, १; ८. ४५, ४; ७७, १; १०. १०३, १३.

उग्राः १. १६६, ६; ८; ५. ५७, ३; ६०, २.

उग्राःऽई॑व १०. ९४, ६.

उग्राणा॑ं ९. ६६, १६.

उग्रात् ८. ४५, ३५.

उग्रान् ६. ६६, ५.

उग्राभि॑ः १. ७, ४; १२९, ५.

उग्रां १०. १०४, ३.

उग्राय॑ १. ३७, ७; ७. २४, ५; ८. ३२, २७; ९६, १०; १०. ११६, ५.

उग्रास॑ः ८. २०, १२; १०. ४४, ३.

उग्रेण॑ ८. १, २१.

उग्रेभि॑ः १. १३३, ६; १७१, ५; ८. ४९, ७.

उग्रेभ्य॑ः ९. ६६, १७.

उग्रेषु॑ २. ११, १७; १०. १५१, ३.

उचथ॑े १. १८२, ८; २. १९, ७.

उचथ॑स्य १. १४३, ६; ५. १२, ३; ७. १८, ५; ८. ८८, ६.

उचथा॑ २. २०, ५.

उचथा॑नि १. ७३, १०; ४. २४, ७.

उचथा॑य १. ११०, १.

उचथ्य॑े ८. ४६, २८.

उच्चा १. २४, १०; २८, ७; ३३, ७; ११६, २२; १२३, २; २. २, १०; ३०, ५; ४०, ४; ९. ६१, १०; १०. १०६, ५; १०७, २; १८३, २.

उच्चाऽच॑क्रं ८. ७२, १०.

उच्चाऽबु॑ध्नं १. ११६, ९.

उच्चैः ५. ३२, ६.

उच्छ ६. ६५, ६.

उच्छ १. ४८, १; ९२, १४; ११३, ७, १२; १७; १९; १२३, ११; १३; १२४, १०; ५. ७९, २; ३; ९; ७. ७६, ६; ७७, ४.

उच्छत् १. ४८, ८; ७. ८१, ६.

उच्छत १०. ३५, ५.

उच्छति १. ४६, १; ७. ७५, ५.

उच्छतु ७. १०४, २३; ८. ४७, १८; १०. ३५, ४.

उच्छन् ७. ९०, ४.

उच्छन्ति॑ ७. ७२, ४.

उच्छन्ती॑ १. ९२, ६; १२४, १; ५. ७९, १०; ६. ६५, १; ७. ७६, ७; ८१, १; ४; १०. ३५, ३.

उच्छन्तीः ४. ३९, १; ५१, २; ३.

उच्छन्ती॑ १. ७१, १.

उच्छन्तु १. १२४, ९; ७. ४१, ७.

उच्छन्त्या॑ १. १८४, १; ५. ६४, ७.

उच्छसि॑ १. ४८, १०.

उच्छात् १. ४८, ३.

उच्छात् १. ११३, १३; १२४, ११.

उच्छान् ४. ५५, २.

उच्छान् ५. ३७, १; ८. १८, २१.

उच्यते॑ ३. ५७, ५; ६. ५५, ४; ८. १३, ८; ९; १०. ६४, १५; १३५, ७.

उच्यते १. ७७, १; ११४, ६; ३. २९, ११; ५. २५, ८; ४४, ६; ६. २८, ६; ७. ८२, २; ८. १३, १९; ९. २४, ७; १०. ९७, ६; १३६, १; १७०, ३.

उच्यसि ५. ८१, ४.

उच्यसे १. ३१, १४; ६. ४५, ६.

उच्येते इति॑ १०. ९०, ११.

उत् १. ९, ४; १०, १; ११, ७; २४, ५; १५; २५, २१; २८, ९; ३३, १४; ३७, १०; ४०, १; ४८, २; ५; ५०, १; ५; १०; १३; ५६, १; ६४, ११; ७४, ३; ८२, ६; ९२, २; ९५, ७[२]; १०२, ४, ७[२]; १०५, १८; ११२, ५; ११३, १६; १७; ११५, १; ११६, ८; ११; २४; ११७, ५; १२; २४; ११८, ६[२]; १२३, १; ६[२]; १२४, १२; १२६, ४; १४३, ७; १५७, १; १६४, १७; २२; ४७; ५१; १८२, ६; ७; १८४, २; १९१, ८; ९; २. १३, १२; १४, ९; १५, ७; २३, ८; २४, ३; ६; ३१, २; ३३, ४; ६; ३८, १; ४; ४२, २; ३. १, १२; ५, ९; १०; ८, २–५; १८, ४; ३०, १७; ३१, ४; ११; ३३, १३; ३७, १०; ३९, ४; ४४, ५; ५४, २१; ४. १, १३; १७; २, २०; ४, ४; ६, ३; १३, १; १५, ७;

१८, ५; ८; ३२, ४; ४५, १; २; ५०, ५; ५३, १; ५७, ४; ५८, १; **५.** ५, ९; ६, ९; ११, ३; २५, ७; ३१, ३; ३२, ७; ३४, ८; ४२, ३; १५; ४५, १; ५२, ८; १७; ५५, ५; ५६, ५; ५९, ४; ७६, १; ८३, ३; ४; ८; १०; **६.** १६, ४५; १७, ६; १८, १३; ३२, २; ३८, १; ४४, १२; ४७, ३; ५; ४८, १७; ५१, १; ५७, ६; ६४, १; २; ७१, ५; ७२, २; ७५, १६; **७.** १, २०; २५; ३, ३; ८, ६; १६, ३^{२}; ११; २२, ८; २३, १; ३२, १२; ३३, ५; १३; ३४, ७; ३५, ८; ३८, २; ४१, ३; ४३, २; ४५, २; ६०, २; ४; ६१, १; ६२, १; २; ६३, १–४; ६६, १४; ६९, ७; ७२, ३; ७६, १; ७७, २; ८१, २; ९९, २; १०४, ४; **८.** ३, १५; ६, ४८; ७, ३; ७; १७^{४}; १४, ८; १३; १९, २३; २३, ५; २४, १७; २५, १९; २१; २७, १२; ४३, १०; ४४, ४; १७; ६१, ७^{२}; ६२, १०^{२}; ६३, २; ६४, १; ६६, ४; ६९, ७; ७०, ९^{३}; ७३, १; ७९, ६; ९३, १; **९.** ५, ५; ३३, ४; ४७, १; ५०, १; २; ५३, १; ७२, १; ८४, ४; ८६, ४०; ४१; **१०.** ५, ५; ८, १; १०, ९; ११, ६; १५, १^{३}; १७, १०; १८, ८; ११; १३; २३, ४; २७, १५; २३; ३५, ६; ८; ३७, २; ३; ९; ३९, २; ८; ९; ४३, ९; ४५, ७; १०^{२}; ५३, ८^{२}; ५५, १; ५९, १; ६७, ३; ४; ८; ६८, ७; ७३, २; ७५, ३; ८५, २१; ९०, ४; ९७, ८; १०१, १; १२; १०२, २; ७^{२}; १०३, ९; १०^{४}; १०५, १०; १०८, ११; १११, २; ११८, २; ११९, २; १२३, २; १३०, २; १३७, १; १३८, २; १३९, १; १४०, २; १४२, ६^{४}; १५३, ३; १५९, १^{२}; १६६, ५; १६७, ४; १७९, १.

उ॒त **१.** १, २; ४, ५; ६; १०, ६; ११, ८; १७, ६; २०, ६; २३, १९; २२; २४, ८; २५, १५; २८, ६; ३१, १८; ३२, ४; १३; ३४, १; ५^{२}; ३६, ६; १५; १७; ३९, २; ४१, ६; ४५, १; ४७, ६; ५१, ३; ५२, १४; ५३, ८; ६७, ५; ७४, ३; ९; ७६, ४; ७९, ६^{२}; ८०, १५; ८१, १; ८२, ५; ८४, १७; ८५, ५; ८६, ३; ९०, ५; ७; ९१, ५; ९४, ५; ६; ८; ११; १६; ९५, ११; ९६, ९; ९८, ३; १००, १९; १०१, ११; १०२, ११; १०३, ८; १०५, १९; १०६, ३; ७; १०७, ३; १०८, ३; ५; ९; १०; १३; १०९, १; २; ८; ११०, ९; १११, ५; ११२, १५; २५; ११३, २०; ११४, २; ७^{३}; १०; ११; ११५, ६; ११६, १०; २५; ११७, १९; ११९, ९; १२२, ४; ६; १२७, ९; १२९, ३; १३७, २; १३९, ८^{२}; १४०, १२^{२}; १४१, १२; १४७, ५; १५१, २; ९; १५३, ४; १५४, ४; १५९, २; १६१, ३; १६२, ५; ६; १०; २२; १६३, १; १६४, २६; १६७, ८; १७०, १; १७१, ३, १७५, ५; १८०, ९; १८१, ८; १८३, ४; १८६, ५–८; १८९, ४; ६; १९१, ३; **२.** ७, २; ३; ९, ६^{२}; १०, २; ११, ६; १२, ५; १३, ८; १६, ६; २३, ७; २४, १; २; १३; २७, ३; ८; ११; १४; २८, ८^{२}; ३०, ७; ९; ३१, ३–५; ६^{२}; ३५, ११; ३६, २; ३७, ४; **३.** ४, ६^{२}; ५, ४; ६, २; ७, ५; १३, ६; १६, ४; १९, ३; १६; २५, १; ३०, ५; ११^{२}; ३२, ८; १२; १३; ३४, २; ८; ९^{२}; ३५, ३; ३६, ३; ३७, २; ३८, २; ३; ४१, ७; ४७, ३; ५१, ५; ५४, ७; १९; ५६, ३; ५; ५९, १; **४.** २, ४; ३, १५; ९, ३; ४^{२}; १२, ५; १५, ८; १७, ८; १०^{२}; १३; १८, ४; ११; २०, ८; २१, ३; ९; २४, ७; २५, ८; २६, ५; २७, २; ३०, ४; ६–८; १२–१८; २२; २३; ३१, ७; ८; ३३, ११; ३४, २; ३; ३८, २; ५–९; ३९, १; ४०, ३; ४; ४२, ४; ४५, ३; ४८, ५; ५०, ९; ५२, ३^{२}; ५५, ५; **५.** १, ६; १०; २, १०; ५, ९; ६, १०; ७, ३; ९; ९, ३; ४; ७; २४, १; २९, ३; ३०, २; ३१, १३; ३३, ७; ८; ३४, ३; ४१, ३; ११; ४२, ५; ८; १२; १८; ४३, ९^{२}; ४६, २; ४^{७}; ५^{२}; ६; ८; ४७, ७; ५२, ८; ९^{२}; ५३, ८; ५५, २; ७; ५६, ७; ५८, १; ५९, ५; ६०, ६; ६१, ५; ६; ८; ९; १८; ६२, ३; ६९, १; ४; ७०, ३; ७५, ४; ७६, ३; ७७, २; ७९, ८; ८१, १; ४^{४}; ५^{३}; ८३, २^{२}; १०; ८५, ४; ८; **६.** १, १०; १५, ११^{२}; १३; १६, ८; ४७; १७, ३; १८, ७; १९, १; ८; २१, ५^{२}; १२; २३, १०; २५, ३; ७; ९; २८, १; ३३, ५; ३८, ४; ४०, १; ४४, १३; ४५, ३; ५; ४७, १^{२}; ७; १९; २९; ४८, २; ४^{२}; १७; १९; ५०, ३; ९; १०; १३; १४; ५१, ८; ५२, १; १३; ५३, १०^{२}; ५४, ६; ५६, २; ३; ६०, १; ६१, ३; ७; १०; ६२, ८; ११; ६३, ९; ६४, ४; ६७, ६; ६८, ७; **७.** २, ६; ५, ४; १२, २; ३; १५, ३; १७, १; २^{२}; १९, ५; २०, ९; २५, ३; २६, ४; ३१, २; ७; ३३, १०–१२; ३४, १८; २३; ३५, १४; ३६, ७; ९; ३८, ५; ४०, ३; ४१, १; ४^{४}; ४९, २^{२}; ५४, ३; ५६, ११; ५७, ६; ५८, १; २; ४; ६३, ५; ६४, २; ६६, ६; ६८, ६–८; ७२, २; ७४, ६^{२}; ८२, ८; ८६, २; ९०, ३; ९५, ४; ९७, १०; ९८, २^{२}; १०४, २२^{२}; २४; **८.** १, ६; २१; २, ३३; ४२; ५, ९^{२}; २१; २६; ६, २२–२४; ३२; ३३;

३९; ७, १२; २४; ९, १०; ११^{२}; १२, ७; १४; १३, २३; १४, ११; १५, ७; १८, ७; ८; ११^{२}; १६; १९, १९; ३७; २०, १५; १६; २१, ८; २३, २; २४, ४; २५, १०; १४; २६, १०; १८; ३०, ४; ३१, १८; ३२, ८; ९; २०^{२}; ३५, १३; १४; १६; ४०, ९; ४३, १२; १३; १७; ४४, २२; ४५, ६; १७; १८; ३३; ३४; ४६, १०; २८; ४७, ५; १२; ४८, १; ५; ८; १४; १५; ५२, ८; ५३, ७; ५४, ६; ५७, ३; ६०, ९; ६१, २; १५; ६६, १०; १४; ६७, १०; ६९, ८; ७०, ५; ७१, १; ७५, २; ७८, ३; ४; ८०, १०; ८३, ९; ८४, ३; ८६, ४; ८८, ४; ८९, ५; ६; ९२, २८; ९४, ४; ९७, १०; **९.** १, ४; ९; २, १०; ४, ३; ६, ३; १३, ४; २२, ५; ६; ३२, ६; ४५, ३; ५१, ५; ५५, ३; ६१, ८; ६२, २४; ६३, ९; १२; ६८, ७; ७९, ३^{२}; ८२, ३; ८७, ९; ८९, ६; ९३, ३; ९६, ३; ५; ९७, १३; २४; ५३; १०७, २०^{२}; **१०.** ४, ७; ७, ७^{२}; १०, ५; १६, ६; ८; १७, २; १८, १; २०, ९; २२, ९; १५; २५, १; ३; २७, २४; २८, १; ३१, २; ४; ११^{२}; ३२, ७; ३३, ८; ३४, २; ३९, ९; ४०, ५; ४२, ९; ११^{२}; ४३, ३; ५; ४८, ८; ५३, ४; ७^{२}; ११; ५५, ३; ६^{२}; ५६, ४; ६०, ३; ६१, ९; १४; १५; २३; ६२, १०; ६३, २; ६४, १०; ६६, ११; ६७, ३; ६९, ४; ५; १०; १२; ७१, ४^{२}; ५; ७३, ३; १०; ७५, ८; ७८, ६; ८१, ३^{२}; ५; ६; ८२, २; ८३, ६; ८५, १०; ८६, ९; १४; ८७, ३; ६; ७; २०; ८८, २; ३; १४^{२}; १५; ८९, ४; ९०, २; ९१, ११; ९२, १२; ९३, ५; ६; ७; १०; ९५, ५; ७; ९६, १०; ९७, २; १६; ९९, ९; १०२, ७; १०४, १०; १०७, ७; १०८, ५; १०९, ६; ११०, २; १११, ९; ११६, ८; ११७, १^{२}; ३; १२१, १; १२४, १; १२५, १; २; ५; ७; १३१, ३; १३६, ५; १३७, १^{२}; १४१, २; १४२, ३^{२}; १४६, ३^{२}; १४८, ३; ४^{२}; ५; १५८, ३; १५९, ३; १६१, १; १८६, २^{२}.

उतऽईव **१.** १६३, ४.

उत्ऽअगाः **८.** ९३, ४.

उत्ऽअजायंत **४.** १८, १; **१०.** ५५, ७.

उत्ऽअंचनः **५.** ४४, १३.

उत्ऽअमंदिषुः **९.** ८१, १.

उत्ऽअयंत् **७.** १०४, ३.

उत्ऽअयंनात् **१.** ४८, ७.

उत्ऽअये **८.** ४१, २.

उत्ऽअर्के **१.** ११३, १८.

उत्ऽअर्वता **६.** १८, ९.

उत्ऽअसृजः **२.** २३, १८.

उत्ऽआचंरत् **७.** ५५, ७.

उत्ऽआजंत् **२.** १२, ३; १४, ३; २४, १४.

उत्ऽआजंत **१.** ११२, १२.

उत्ऽआजंन् **१०.** ६२, २.

उत्ऽआनंट् **१०.** १९, ५.

उत्ऽआरः **१०.** ४५, ५.

उत्ऽआरिथ **२.** ९, ३.

उत्ऽइंतः **१०.** १२१, ६.

उत्ऽइंता **१.** १०८, १२; ११५, ६; **५.** ६२, ८; ६९, ३; ७६, ३; **६.** ५१, १; **७.** ६, ७; ४१, ४; ७६, ३; **८.** ७२, १७; १०३, ११.

उत्ऽइंर्ति **६.** १५, ११.

उत्ऽइंते **३.** १५, २; **५.** ५४, १०; **७.** ६३, ५; ६६, ४; १२; **८.** १, २९; १३, १३; २७, २१.

उत्ऽइनक्षंतं **१०.** ८, ९.

उत्ऽइयर्थि **१०.** ३७, ४.

उत्ऽईरत् **४.** २, ७.

उत्ऽईरते **२.** १७, १.

उत्ऽईरयंति **१.** १६८, ८.

उत्ऽईरयंती **१.** ११३, ८.

उत्ऽईरयंती **८.** १०१, १६.

उत्ऽईराणाः **४.** ३९, ५; **७.** ४४, २.

उत्ऽईषितः **१०.** ११९, १२.

उत्ऽवत् **४.** २१, ९,

उत्ऽऋचिं **१.** ५३, ११; **१०.** ७७, ७.

उत्ऽकृपन् **१०.** १५५, २.

उतोइर्ति **१.** २३, १५; ११६, १४; १३१, ६; १३४, ६; १५३, ४; १६२, ६; १२; **२.** ११, ५; १८, २; **३.** ७, ६; १०; ५४, ४; **४.** ९, ४; ३८, १; **५.** ६, ९; २५, ८; ३८, ४; ५५, ४; **६.** ४७, १; **७.** १, ८; २९, ४; ५३, ३; **८.** ६, ३१; १३, ९; २८; ३१; २१, ८; २५, २३; २६, ११; ३३, १७; ४०, १०; ७२, ६; ९३, ५; **९.** ५७, ४; ६४, २६; ९९, ४; **१०.** ७१, ४; ७३, ९; ११७, १; २; १४६, ३; १६८, १.

उत्ऽओजसः **५.** ५४, ३.

उत्ऽओजसं **१०.** ९७, ७.

उत्ऽचरंत् **७.** ६६, १६.

उत्ऽचरंतं **४.** २५, ४; **६.** ५२, ५; **७.** १०४, २४; **१०.** ५९, ४; ६.

उत्ऽचरंसि **१०.** ३७, ५.

उत्ऽचरांतः **८.** ४०, ८; **१०.** ६८, १०.

उत्ऽजिहांनाः **५.** १, १.

उत्तंभिता **१०.** ८५, १^{२}.

उत्ऽतमः **३.** ५, १०; **९.** ८५, ३; १०८, १६; **१०.** १५९, ३; ४; १६६, ५.

उत्ऽतमं **१.** २४, १५; २५, २१; ५०, १०; १५६, ४; १६३, ७; **२.** १, १२; २३, १०; **४.** ३१, १५; ३६, ८; ५४, २; **५.** २५, ५; ५९, ३; **९.** २२, ५; ६; ५१, २; ६३, २९; ६७, ३; २८; १०७, १; **१०.** ७५, १; १७०, ३.

उत्ऽतमा **३.** ५६, ८; **१०.** ९७, १८; २३.

उत्ऽतमानि **१.** ९१, १८; **५.** २८, ३.

उत्तमाय्यं **९.** २२, ६.

उत्ऽतमे **१.** ३१, ७; **२.** ४१, ५; **५.** ६०, ६; **८.** ५१, ४; **९.** ६१, २९.

उत्ऽतमेभिः **६.** ६०, ३.

उत्ऽतरः **४.** १८, ९; ३०, १; **८.** १४, १५; **९.** १०७, १८; **१०.** ८५, ४०; ८६, १; १०२, १०.

उत्ऽतरं **१.** ५०, १०; ९५, ८; १५४,

१; २. २३, ८; ६. १६, १७; ९. १०७, २; १०. ८४, ६.
उत्ऽतंरस्मात् १०. ४२, ११; ९८, ५.
उत्ऽतंरस्मिन् १०. ९८, ६.
उत्ऽतंरा १. ३२, ९; ३. ३३, ८; ७. ९५, ४; ८. २०, ६; ३३, १८; १०. १०, १०; २८, ६; १४५, ३.
उत्ऽतंराणि ८. ४१, ९; १०. ६७, १०.
उत्ऽतंरात् ४. २६, ६; ५. ६०, ७.
उत्तरात् ६. १९, ९; ८. ६१, १६.
उत्तरात्तात् १०. २७, १५; ३६, १४.
उत्ऽतंरान् १. ११३, १२.
उत्ऽतंराभ्यः १०. १४५, ३.
उत्ऽत्तंरां १. ५०, ११.
उत्तंरांऽउत्तरां ४. ५७, ७.
उत्ऽतंरे १. ७, ७; ६. १९, १२; १०. ७२, १; १०३, ११.
उत्ऽतरे १०. १४५, ३.
उत्तानः ४. १३, ५.
उत्तानऽपंदः १०. ७२, ३; ४.
उत्तांनऽपर्णे १०. १४५, २.
उत्तानयोः १. १६४, ३३.
उत्तानऽहंस्तः ६. १६, ४६; ६३, ३.
उत्तानऽहंस्ताः ३. १४, ५; १०. ७९, २.
उत्तानां ५. १, ३; १०. २७, १३; १४२, ५.
उत्तानायां १. १६४, १४; २. १०, ३; ३. २९, ३.
उत्ऽतिष्ठंन् ७. ३३, १; ८. ७६, १०.
उत्थितं १०. १४९, २.
उत्ऽनिनीथः १. १८१, १.
उत्ऽनींताः ९. ८१, १.
उत्ऽनीयमांनाः ३. ८, ९.
उत्ऽपतंन् २. ४३, ३.
उत्ऽभित् ८. ७९, १.
उत्ऽभिदंः १. ८९, १; १३९, ६; ५. ५९, ६; १०. ११६, ९.
उत्ऽभिद्रं १. १०२, ९.
उत्ऽभिदां १०. ७६, १.
उत्ऽभृतं ३. २१, ५; ४. ४७, २७.
उत्ऽमंदिताः १०. १३६, ३.
उत्ऽयत् ७. ८१, २.
उत्ऽयंतः ६. ६८, १; ९. ८६, ४६.
उत्ऽयंतं १. ८०, ९; ८. ६९, ९; ९. ६८, ५; १०३, १; १०. २२, ७; ५०, ६.
उत्ऽयंता २. ३१, ७; ८. ७४, ३; १०१, ७.
उत्ऽयंतानि १०. ८, २.
उत्ऽयुति ८. २७, १९.
उत्ऽयंतिं १. १९०, ३.
उत्ऽयन् १. ५०, ११; १२४, १; १६३, १; ७. ६०, १; १०. ८८, ६.
उत्ऽयंतें १०. ३७, ७.
उत्ऽयंता १. १७८, ३.
उत्ऽयंमीयसी १०. ८६, ६.
उत्ऽवतंः ३. २, १०; ५. ८३, ७; ७. ५०, ४; ८. ६, २९; १०. १२७, २; १४२, ४.
उत्ऽवतां १. ३५, ३.
उत्ऽवरींवृजत् ६. ५८, २.
उत्ऽवर्धयंन् ९. ११४, २.
उत्ऽवव्रुपाणः ४. २०, ७; २९, ३.
उत्ऽश्वंचंमाना १०. १८, १२.
उत्ऽश्वासे ९. ८६, ४३.
उत्संः १. १५४, ५; ५. ४५, ८; ८. ६१, ६; ९. ८९, ६; १०७, ४; १०. ३०, ८.
उत्सऽधिं १. ८८, ४.
उत्सं १. ६४, ६; ८५, ११; १२१, ८; २. १६, ७; २४, ४; ३. २६, ९; ५. ३२, १; ५२, १२; ५४, ८; ६. ४४, २४; ७. ५७, १; ८. ७, १०; १६; ९. ९७, ४४; ११०, ५; १०. ३०, ९; ४५, २; १०१, ११; १४३, ६.
उत्ऽसवे १. १०२, १.
उत्ऽसवेषु १. १००, ८.
उत्संस्य १०. ५, १.
उत्साः ५. ५७, १.
उत्सान् ५. ३२, २.
उत्ऽसिनांति १. १२५, २.
उत्ऽसिसृप्सतः ८. १४, १४.
उत्ऽस्नायं २. १५, ५.
उत्ऽहर्षयंति ५. २७, ५.
उदंक् ३. ५३, ११; ८. ४, १; २८, ३.
उदकं १. १६१, ८; १०; १६४, ७; ४०; ५१; १९१, १४; ९. ६७, ३२; १०. १०२, १०.
उदकात् १०. १६६, ५.
उदकात्ऽइंव १०. १६६, ५.
उदंक्तात् ७. ७२, ५; १०४, १९; १०. ८७; २०; २१.
उदऽग्राभस्यं ९. ९७, १५.
उदंचः १०. ८६, २२.
उदंचं २. १५, ६.
उदऽधिं ७. ९४, १२.
उदधीन्ऽइंव ३. ४५, ३.
उदऽधेः १०. ६७, ५.
उदन् १. १०४, ३.
उदनिं १. ११६, २४; १०. ६८, ८.
उदनिऽमान् ५. ४२, १४.
उदन्युजाऽइंव १०. १०६, ६.
उदन्यन् १०. ९९, ८.
उदन्यवंः ५. ५४, २.
उदन्यवें ५. ५७, १.
उदन्याःऽइव २. ७, ३.
उदन्युवंः ९. ८६, २७.
उदन्ऽवतां ५. ८३, ७.
उदन्ऽवतीः ७. ५०, ४.
उदऽप्रुतः ४. ४५, ४; ७. ४२, १; ९. १०६, ८; १०. ६८, १.
उदऽप्रुतं ५. ७४, ४; ८. १०८, ७.
उदऽभिः १. ८५, ५; १०४, ४; २. १३, ५; ८. ९८, ७; १०. ७८, ५.
उदऽमेघे १. ११६, ३.
उदरें १. ४२, ९; ८. १, २३; २, १; ७८, ७; १०. ८६, २३.
उदरंस्य १. १६२, १०.
उदरें १. ३०, ३; ८. ९१, ५.
उदरेषु १. २५, १५.
उदऽवाहासंः ५. ५८, ३.
उदऽवाहेनं १. ३८, ९.
उदऽव्रजे ६. ४७, २१.
उदा ५. ४१, १४.
उदाऽइंव ८. ९८, ७.
उदारथिः १. १८७, १०.
उदितं १०. १५१, २; ३.
उदीचः १०. १३१, १.

उदुंबलौ **१०.** १४, १२.

उद्गाताऽइंव **२.** ४३, २.

उद्धरंन् **१०.** ६८, ४.

उद्धिंतं **८.** ५१, २.

उद्रः **१.** ११२, १२; **७.** ६५, ४; **८.** ३२, २५; **१०.** ६८, ५; १०२, ४.

उद्रःऽइंव **८.** १९, १४.

उद्रा **५.** ४५, १०; ८५, ६; **८.** १००, ९.

उद्राऽइंव **४.** २०, ६; **१०.** ६८, ४.

उद्यंतऽस्रुचे **१.** ३१, ५.

उद्यतें **५.** ५५, ८.

उद्यते **१.** १६४, ४७.

उद्रिणं **२.** २४, ४; **८.** ७, १०; **९.** ७४, ७; **१०.** १०१, ५; ६.

उद्रीऽइंव **८.** ४९, ६.

उद्वतऽस्सु **१.** १६१, ११.

उनर्त्त **५.** ४२, ३.

उनर्त्ति **५.** ८५, ४.

उनत्ति **५.** ८५, ३.

उनप् **२.** १३, ९.

उनोति **५.** ३१, १.

उंदन् **२.** ३, २.

उंदंति **१.** ८५, ५; **५.** ५४, ८.

उंध्रि **५.** ८३, ८.

उर्प **१.** १, ७; २, ४–६; ३, ५; ६; ४, २; ११, ६; १२, ७; १०; १३, ३; ७; ८; १०; १२; १६, २; ४; ५; २१, १; ४; २२, ५; ६; ९; १२; २३, १७; १८; २५, ४; ३०, ८; ३३, १; २; ३६, ७; ३८, ५; ४०, १; ८; ४७, ३; ८; ४८, ११; ४९, १; ५३, ७; ६२, १२; ६५, १; ६८, १; ७१, १; ७२, ५; ७४, ६; ७७, ३; ८१, ८; ८२, ५; ६; ८३, २; ८४, २; ८७, २; ८९, २; ९२, ७; ९३, ११; ९५, १; ६; १०७, २; ११४, ९; ११६, १९; ११७, १; ११८, १०; १२४, ११; १२५, ४^{२}; १२६, ३; १३०, १; १३४, २; १३५, १; ३; ५; ८; १३६, ६; १३७, १; ३; १३८, ४; १३९, १; ५; १४०, ४; १४१, १; १४२, २; ११; १३; १४५, ५; १४९, १; १५१, ४; ७; १५८, ३; १६१, ६; ७; १०; १६२, ७^{२}; २१; १६३, १२; १३; १६४, ४; २६; ४२; १६५, ५; १६६, २; १६७, १; १७१, २; १७३, १०; १७७, १; ३; ५; १७९, ५; १८०, ६; १८२, २; १८३, ५; १८५, ७; १८६, ४; १८७, ३; १८८, १०; १९०, २; **२.** ३, १०; ५, ६; ८, १; १७, ७; १८, ८; २४, १५; २७, ७; १३; ३०, ३; ७; ११; ३४, १४; ३५, १; ३; ५; ३९, ८; **३.** २, ३; ६; ९; ३, ९; ४, १०; १२, ७; २५, ४; २७, १२; २९, १६; ३३, ५; ३५, २^{२}; ३७, ५; ४३, १^{२}; २; ५१, २; ५२, ५; ६; ५३, ११; ५५, १; २१; ५६, २; ६०, ७; **४.** ४, ९; ५, १; ८; ६, २; १४, १; १६, १; २१, १; ५; २२, १०; २९, १; २; ४; ३३, २; ३४, १; ५; ६; ३५, १; ३७, १; ४१, ८; ९^{२}; ४४, ४; ४६, ५; ५१, ११; ५६, ५; ५७, ५; ५८, १; २; **५.** २, ५; ४, ५; ८, ४; ९, ५; ११, ४; ३०, ९; ३९, ४; ४०, ४; ४२, ७; १५; ४३, १; ४९, २; ४; ५१, १२; ५३, ३; ५४, ७; ५५, ५; ६२, ४^{२}; ६३, ३; ६५, ३; ७१, १; ३; ७५, ८; ७८, १; **६.** १, ६; ८, ४; १५, ६; १६, ३७; ३८; १७, ७; २०, ८; २१, ११; २८, २; ४; ८^{४}; ३१, ५; ३६, ४; ४०, ४; ४१, १; ४; ४५, २३; ४७, ८; २९; ४८, ११; १६; ५०, ६^{२}; ५२, ८; ९; १३; ५५, ४; ५७, २; ६०, १४; ६२, ४; ६७, २; ३; ६८, १०; ६९, ४; ७२, २; ७५, ८; १३; **७.** १, ३; ६^{२}; २, १; २; ६, ६; १४, ३; १५, ९^{२}; १६, ११; १८, ३; ४; १९, ११^{२}; २३, ३; २६, ५; २८, १; २९, २; ३१, ९; ३२, १; ३३, ९; १४; ३७, ७; ४४, ३; ४६, २; ५५, २; ६९, ६; ७०, ६; ७१, ४; ७२, २; ७३, ४; ७४, ३; ४; ८३, ३; ९२, १; ९३, ६; ९५, ४; ५; १०३, ३; **८.** १, ४; ८; ४, ९; ११; १४; ५, ७; १३; ३०; ६, ८; २७; ४०; ४२; ७, ११; २७; ८, ६; ११, ४; १४, १२; १७, २; ४; १८, १४; १५; २०, १४; १८; २२; २१, २; २२, ७; १२; १३; २४, २३; २५, २१; २६, ४; ७; ९; २७, ११; २०; ३२, ६; १७; ३४, १; ३५, ७; २०; २१; ४०, ८; ४१, २; ४३, ४; ४४, ३; ५; ४५, ७; ४६, ३०^{२}; ४९, ५; ६; ५०, ३; ४; ५२, ३; ५४, ३; ७; ५७, ३; ४; ६७, १०; ६८, १४; ६९, १३; ७१, ९; ७२, ७; १२; १५; ७३, ३; १४; ८१, ५; ७; ८६, २; ८७, ३; ४; ९०, १; ९१, ५; ९२, १०; ९३, ३१; ९६, ८; १२; ९८, ७; १२; ९९, १; ४; १००, ११; १०२, ९; १३; १०३, १४; **९.** ११, १; ६; १५, ७; १९, ६; ४९, २; ६७, २९; ६९, १; ४; ७१, ५; ७२, ९; ७६, ३; ७८, १; ८६, ७; ३२; ३९; ९२, २; ९३, ५; ९५, ३; ९७, ५; २०; ३३; ३८; १०२, २; **१०.** १०, १०; १४, १०; १६, ५; १८, ८; १०; १२; २४, २; २८, १२; २९, ३; ३१, १; ३; ५; ३२, २; ३४, १०; ३५, ७; ३६, ७; ४०, ७; ४२, २; ६०, ४; ६१, ९; १०; १२; ६६, ७; ७०, ९; १०; ७२, ८; ९; ७३, ४; ५; ११; ८३, ६; ८५, १५; ८६, २०; ८७, १–३; ८८, १९; ९१, ११; ९४, ५; ९५, १७^{२}; ९७, ४; १४; ९८, ९; १२; ९९, ८; १२; १०२, ७; १०४, १; ६; ७; १०६, ११; १०९, ७; ११४, २; ११७, १^{२}; ५; ११९, ४; १२३, ६; १२४, १; १२५, ४; ७; १२७, ७; ८; १३०, २; १३६, ७; १३७, ७; १४०, २; १४५, ६; १५१, ४; १५३, १; १५४, १; १६७, २; १६९, ४; १८३, २.

उपऽअंशु १०. ८३, ७.
उपऽअयने २. २८, २.
उपऽअरणे ८. ३२, २१.
उपऽअरे ७. ८६, ६.
उपऽअवति १०. १४६, २.
उपऽअवसृज १०. ११०, १०.
उपऽआगहि १. ९१, १०; २. ३२, ५.
उपऽआचरत् १. ४६, १४.
उपऽआचरेत् १०. १५९, २.
उपऽआजतु १०. १९, २.
उपऽआभृति १. १२८, २.
उपऽआयातं ७. ७१, २.
उपऽआरिम १०. १६४, ३.
उपऽआरुहः ९. ६८, २.
उपऽआसते १. १६२, १२; १०. १२१, २; १९१, २.
उपऽइतयः १०. ६९, १.
उपऽइतिः १. ७६, १.
उपऽइतौ ३. १८, १.
उपऽइव ८. ३, २१.
उपऽईयुषः १०. ३९, ८.
उपऽईषे १. १२९, ८.
उपऽउप १. १२६, ७; ८. ५१, ७; ७४, ९.
उपऽकक्षासः १०. ७१, ७.
उपऽक्षितः ८. १९, ३३.
उपऽक्षियंतः ३. ५९, ३.
उपऽक्षेतारः ३. १, १६.
उपऽक्षेति १. ७३, ३.
उपऽगंतवै १०. १६०, ५.
उपऽच्यवं १. २८, ३.
उपऽजग्मुषः १. ५३, ९.
उपऽजग्मुषे १०. ११७, २.
उपऽजायते १. २५, ८.
उपऽजिह्विका ८. १०२, २१.
उपऽजीवति १. १९०, ५.
उपऽतिष्ठंत १. १३५, ८.
उपऽतिष्ठंते ३. २२, ३.
उपऽतिष्ठमानः १०. ११७, ८.
उपऽतिष्ठमानां ८. १०१, १६.
उपऽदद्यमाने ६. ४९, १३.
उपऽदस्यति ८. ४३, ३३.
उपऽदृक् ८. १०२, १५; ९. ५४, २.
उपधी इवेत्युपधीऽइव २. ३९, ४.
उपऽनायं ९. ९१, ४.
उपऽनिपद्यमानं १. १५२, ४.
उपऽनीतं १. १२१, ९.
उपऽनीता १०. १०९, ४.
उपपसिऽवांसः ९. ८५, ११.
उपऽपर्चनं ६. २८, ८.
उपऽपृक् १. ३२, ५.
उपऽप्रक्षे ५. ४७, ६.
उपऽप्रयन् १. १०३, ४.
उपऽप्रयंतः १. ७४, १; ४. ३९, ५; ७. ४४, २.
उपऽप्रुतं ९. ७१, २.
उपऽबर्बृहत् ५. ६१, ५.
उपऽबर्हणं १०. ८५, ७.
उपऽबर्हणीं १. १७४, ७.
उपब्दिः १. ७४, ७; १६९, ७; ९. ८८, ५; १०. ६१, ९.
उपब्दिऽभिः १०. ९४, ४; १३.
उपऽब्दैः ७. १०४, १७.
उपऽब्रवामहै १०. ३७, ५.
उपऽब्रुवे १. १८५, ११; १८८, ८.
उपऽब्रुते १. ४०, २; ६. ६१, ५.
उपऽमः ९. ८६, ३५.
उपऽमंत्रिणः ९. ११२, ४.
उपऽमन्युं १. १०२, ९.
उपऽमं १. ६१, ३; ११०, ५; ५. ३, ३; ६४, ४; ७. ३०, ३; ४; ३९, ७; ८. ५३, १; ६२, ८; ८०, ५; १०. २९, ३.
उपमऽश्रवः १०. ३३, ७.
उपमश्रवःऽतमं २. २३, १.
उपमऽश्रवसः १०. ३३, ६.
उपमस्यं ४. ४२, १; १०. ५, ६.
उपऽमस्यां १. १४५, ५.
उपऽमा १. ३१, १५; ११३, १५; १२४, २; ८. २९, ९; ६९, १३.
उपऽमातयः ४. २३, ३; ८. ४०, ९.
उपऽमातिः ४. ४३, ४.
उपऽमातिं १०. ६१, २१.
उपमातऽइव ६. ६७, ६.
उपमातिऽवनिः ५. ४१, १६.
उपऽमाते ८. ६०, ११.
उपऽमादे ३. ५, ५.
उपऽमान् १०. ८, १.
उपऽमानां ८. ६१, २.
उपऽमानि ८. ९९, २.
उपऽमां ५. ३४, ९.
उपऽमासः ५. ५८, ५.
उपऽमित् १. ५९, १; ४. ५, १.
उपऽमिमीहि १. ८४, २०.
उपऽमे ८. ८२, ४.
उपऽमेभिः १. ३३, २.
उपऽयंतः १०. १०२, ५.
उपऽयंते २. ३३, १२.
उपऽयंति २. २, ११.
उपऽयाति ४. ४, १०; ७. १, १२.
उपऽयाथः १. ३४, ९; १८३, १.
उपऽयासि १०. ११, ५.
उपऽये ८. ४७, १२.
उपरः १०. २७, २०.
उपरऽताति १. १५१, ५; ७. ४८, ३.
उपरं १. ६२, ५; ५. ३१, ११; ६. २१, ११.
उपरस्य १. ७९, ३; १०४, ४; ४. २, १८; ५. ४४, २; १०. ९४, ५.
उपरा १. ५४, ७; १६७, ३.
उपराः १. ६२, ६; ३. ५६, २; ५. २९, ५; ७. ८७, ५; १०. २७, २३.
उपरान् २. ४, ९.
उपराय ७. ८७, ४.
उपरासः ९. ७७, ३; १०. १५, २.
उपरासु १. १२७, ५; ४. ३७, ३.
उपरि १. २४, ७; ३४, ८; ४. ३१, १५; ५. ६१, १२; ८. ३३, १९; ४७, २; १०१, ९; ९. ५४, ३; १०. ३४, ९; ७५, ३; १२९, ५.
उपरिऽबुध्नान् १०. ७३, ८.
उपरिऽमर्त्यं ८. १९, १२.
उपरिष्टात् ९. ९१, ४.
उपरिऽस्पृशं १०. १२८, ९.
उपरे १. १६४, १२; १०. ४४, ७.
उपरेषु १. १२८, ३; १०. १७५, ३.
उपलऽप्रक्षिणी ९. ११२, ३.
उपऽवक्ता ४. ९, ५.
उपवक्ताऽइव ६. ७१, ५; ९. ९५, ५.

उपऽवसुः ९. ८४, ३; ८६, ३३.
उपऽवसुं ६. ५६, ६.
उपऽवाकं १. १६४, ८.
उपऽवाक्यः १०. ६९, १२.
उपऽवाच्यः १. १३२, २; ४. ५४, १.
उपऽविदा ८. २३, ३.
उपऽवोचत १. १२७, ७.
उपऽशाकेभिः १. ३३, ४.
उपऽशिक्षन् ५. ४०, ८.
उपऽशिश्रियाणाः ७. ५६, १३.
उपऽशृण्वंति १०. ९७, २१.
उपऽश्रितः ७. ८६, ८.
उपऽश्रुति ८. ८, ५; ३४, ११.
उपऽश्रुतिं १. १०, ३.
उपऽश्रोता ७. २३, १.
उपऽसदं २. ६, १.
उपऽसद्यं ३. १४, ५.
उपऽसद्यः २. २३, १३; ३. ५९, ५; १०. ४७, ६.
उपऽसद्याय ७. १५, १.
उपसि ५. ४३, ७; १०. २७, १३.
उपऽसिष्मियाणा १०. १२३, ५.
उपऽसृजंति २. १, १६; २, १३.
उपऽसेचनाय १०. ७६, ७.
उपऽसेचनासः ७. १०१, ४.
उपऽसेचनी १०. २१, २; १०५, १०.
उपऽसेदुषे ८. ४७, १६.
उपऽस्तरणं ९. ६९, ५.
उपऽस्तिरे ९. ६२, २८.
उपऽस्तिरे २. ३१, ५; ४. ३३, १; ५. ८५, १; ९. ७१, १.
उपस्तयः १०. ९७, २३.
उपस्तिः १०. ९७, २३.
उपऽस्तुत ९. ८७, ९.
उपऽस्तुतः ७. २७, ३; १०. ९६, ५.
उपऽस्तुतः १. ३६, १०.
उपऽस्तुतं १०. ६०, १.
उपऽस्तुतं १. ३६, १७; ११२, १५; ८. ५, २५.
उपऽस्तुतस्य १०. ११५, ८.
उपऽस्तुता १. १३६, १; ५. ७६, २.
उपऽस्तुताः १. ११०, ५.
उपऽस्तुतासः ८. १०३, ८.
उपऽस्तुतासः १०. ११५, ९.
उपऽस्तुतिः १. १५८, ४; ७. ८३, ७; ८. १, १६; १०. ६४, ११.
उपऽस्तुतिं १. १४८, २; १९०, ३; ४. ५६, ५; ८. ४, ६; २७, ११; ६२, १; ७०, १३; ८४, ४.
उपऽस्तुतीनां ८. २७, १५.
उपस्तुते इत्युपऽस्तुते २. ३२, १.
उपऽस्तुतौ १. १८१, ७; १०. १६७, ३.
उपऽस्तुत्यं १. १३६, २; १६३, १.
उपऽस्तुत्यां ६. ६१, १३.
उपऽस्तृणंति १. १६२, १६.
उपऽस्तृणीषणिं ६. ४४, ६.
उपऽस्थं २. ३५, ९; ४१, २१; ७. ६, ६.
उपस्थऽसत् १०. १५६, ५.
उपऽस्था १. ३५, ६; १२४, ५.
उपऽस्थात् १. ९५, ४; ३. ३३, १; ६. ६२, ६; ७. ९, १; ६३, ३; ८८, ७; १०. १७, १२; १८, १०; १६१, २.
उपऽस्थाय ३. ४८, ३.
उपऽस्थायं १. १४५, ४.
उपऽस्थे १. ३१, ९; ३५, ५; ९५, ५; १०९, ३; ११५, ५; ११७, ५; १४४, २; १४६, १; १८५, २; ५; २. १४, ७; ३. ५, ८; ८, १; २६, ९; २९, १४; ५. १, ६; १९, १; ६. ७, ५; ८, ४; ७५, १; ४; ७. ५, १; ३४, २५; १०४, ९; ८. ४०, ४; ४२, २; ९४, २; ९६, १५; ९. २६, १; ७१, ५; ७४, ५; ७६, ५; ८६, २५; ८९, १; १०९, १३; १०. ५, १; ७; ८, १; ७; १५, ७; ४५, ३; ४६, १; ६९, १०; ७०, ६; ७; ७९, ३; ८५, २; ९५, १४; १०१, १०.
उपऽस्पिजं १०. ८८, १८.
उपऽस्पृशः १०. २२, १३.
उपऽहत्नुं २. ३३, ११.
उपऽहस्वानः ८. ४५, २३.
उपऽहूताः १०. १५, ५.
उपऽह्वरे १. ६२, ६; ८. ६, २८; ६९, ६; ९६, १४.
उपऽह्वरेषु १. ८७, २.
उपाकऽचक्षसं ८. ६, २५.
उपाकयोः १. ८१, ४.
उपाके १. २७, ६; १७८, ३; ४. १०, ५; ११, १; १६, १४; २०, ४; ७. ३, ६; ४२, ३; ७३, २; ८. ९६, ३.
उपाके इति १. १४२, ७; ३. ४, ६; १०. ११०, ६.
उपानसः १०. १०५, ४.
उपो इति १. ३९, ६; ६१, १४; ८२, १; १२४, ४; ३. ३५, ३; ७. ६७, २; ७७, १; ८४, ३; ८६, ३; ९२, १; ९३, ३; ८. २३, ९; २४, १४; ९६, ६; १०३, १; ९. ६१, १३; ६९, २.
उप्यते १. १७६, २.
उब्जः ४. १९, ५.
उब्जतं ७. १०४, १.
उब्जतं १. २१, ५.
उब्जन् १. ५२, २.
उब्जंतु ६. ५२, १.
उब्धं ४. १, १५.
उभयतः ५. ८१, ४; ९. ८६, ६.
उभयत्वं ३. ५३, ५.
उभयं १. १९०, ७; २. ९, ५; ८. ६१, १; १०. ३२, १; ६४, १४; ८४, ७.
उभयंऽकरं ८. १, २.
उभयस्य ४. ५३, ६; ६. १९, १०; ४७, १६; ७. ९, १; ३३, १२; ८२, ४; ८३, ५; ८. १०१, १०; ९. ८१, २; १०. १३, ५[2].
उभया २. ६, ७.
उभया १०. १०८, ६.
उभयाः २. १२, ८.
उभयादतः १०. ९०, १०.
उभयान् १. १८९, ७; ४. २, २; ६. १५, ९; ३३, ३.
उभयानि ६. १९, १३; ७. २, २.
उभयाय १. ३१, ७; १०. ३७, ११.
उभयाविन् १०. ८७, ३.
उभयाविनं ८. १, २.
उभयासः १. ६०, २; २. २, १२; ४. २४, ३; ६. १, ५; ७. १, २०; २५; ८३, ६.

उभयाहस्ति ५. ३९, १.

उभयाहस्त्या १. ८१, १.

उभये २. २४, १०; ३. ३२, १४; ४. ३९, ५; ५. ५९, ७; ७. ८२, ९; १०. ९२, २.

उभयेभिः १. १८५, ४.

उभयेभ्यः १. ९१, २३.

उभयेषां १. २६, ९.

उभयेषु १. १२२, १४; ४. ४४, ६.

उभयोः १. १२०, १; ६. २५, ६.

उभा १. २२, २; २३, २; ४६, १५[२]; १११, ४; १२०, १२; १२४, ५; १४०, ३; १४१, ४; १८२, ४; १८५, ९; २. २७, १५; ३. ३, ११; ४. ४, १४; ५. ३८, ३; ४४, १२; ४६, २; ६८, २; ८६, १; ६. ६०, १३[४]; ६९, ८; ७. १, १७; ३७, ३; ९३, १; ८. ५, २९; ३१, ८; ६१, १८; ७२, १२; ८६, १[३]; १०१, ७; ९. ५, ७; १०. १४, ७; ८५, ९; ८६, १४; ८७, ३; १०५, २; १२५, १[२]; १२८, ७; १३१, ५.

उभाभ्यां ९. ६७, २५.

उभे इति १. १०, ८; ३३, ९; ३५, ९; ५४, २; ९५, ५–७; १३३, १; १४१, ११; १४७, १; १८५, ४; ९; २. १, १५; २, ४; २७, १५; ४३, १; ३. १, १०; २, २; ३१, १७; ३४, १; ५३, १२; ५४, १५; ५५, २०; ४. ७, ८; १६, ५; १९, १; ४२, ६; ५५, ३; ५. ६, ९; ३०, ९; ३१, ६; ३७, ५; ८२, ८; ६. ३०, १; ४६, ५; ४८, ६; ५२, १४; ६६, ६; ७. २०, ४; ३४, २३; ६०, २; ८७, ३; ९६, २; ९९, १; ८. ६, ५; ३८; २०, ४; २५, १८; २१; ३९, १; ५२, ७; ६४, ४; ९३, १२; ९८, ५; १०३, ७; ९. १८, ६; ३२, ४; ७०, २–५; ८१, ५; ९७, ३८; १०१, ७; १०. १, ७; १३, ५[२]; १७, ६; ३०, ९; ३९, १२; ६४, १४; ६५, ५; ७६, १; १०१, १०; ११; ११९, ७; १३४, १; १४०, २; १४५, ५; १४७, १; १६६, ३.

उभौ १. १७९, ६; २. २७, १५; ७. १०४, १३; १०. ८३, ७; १०६, १; १३६, ५.

उभ्राः १. ६३, ४.

उरः १. १५८, ५.

उरणं २. १४, ४.

उरवः २. २७, ३; ५. ४७, २; ५७, ४; ६. २१, १२; ७५, ९; ८. १६, ४; ९. २२, २.

उरवे १. १३६, २.

उरा १०. ९५, ३.

उराणः ३. १९, २; ४. ६, ३; ४; ७, ८; ६. ६३, ४; ९. १०९, ९.

उराणं १. १७३, ७.

उराणाः ७. ७३, ३.

उरा ८. ३४, ३.

उराऽमथिः ८. ६६, ८.

उरु १. ३६, ८; ८५, ६; ७; ९१, २२; ९५, ९; १०५, १७; ११७, २१; १२१, १; १५५, ४; १५९, २; २. २७, १४; ३. २२, २; ५४, १९; ४. २५, ५; ४३, ५; ५२, ५; ७; ५३, २; ५. १, ११; ४४, ६; ६४, ६; ६५, ४; ६. ३, १; २०, ५; ४७, ४; १४; ५०, ३; ६१, ११; ६२, १; ६९, ५; ७. ५, ६; ६०, ११; ९०, ४; ९८, ३; ८. १, २३; २५, १६; ३६, १; ६३, ९; ६७, ७; ६८, १२[३]; ७५, ११; ७९, ३; ९. ६८, २; ८१, ५; ९१, ६; ९४, ५; १०. २१, ८; ६३, १२; ८९, २; ९२, ४; ५; १२४, ६; १२७, २; १२८, ५; १४७, ५; १७०, ३.

उरुऽअज्रे १०. २७, ९.

उरुऽइव ९. ९६, १५.

उरुः २. १३, ७; ६. १९, १; ४५, ३१; ८. ३१, ११; १०. १०७, १.

उरुऽकृत् ८. ७५, ११.

उरुऽक्रमः १. ९०, ९; ३. ५४, १४; ५. ८७, ४; ८. ७७, १०.

उरुऽक्रमस्य १. १५४, ५.

उरुऽक्रमा ७. ९९, ६.

उरुऽक्षयां १. २, ९.

उरुऽक्षयाः १०. ११८, ९.

उरुऽक्षयेषु १०. ११८, ८.

उरुऽक्षितिं ७. १००, ४.

उरुऽक्षितौ ९. ८४, १.

उरुऽगव्यूतिः ९. ९०, ४.

उरुऽगाय १०. २९, ४.

उरुऽगायः १. १५४, १; २. १, ३; ८. २९, ७; ९. ६२, १३.

उरुऽगायं ६. २८, ४; ६५, ६; ७. ३५, १५; १०. १०९, ७.

उरुऽगायस्य १. १५४, ६; ३. ६, ४; ९. ९७, ९.

उरुऽगाया ४. १४, १.

उरुऽगायाय १. १५४, ३; १५५, ४; ४. ३, ७; ७. १००, १.

उरुऽचक्रयः ५. ६७, ४; ८. १८, ५.

उरुऽचक्रिः २. २६, ४.

उरुऽचक्रे ९. ८९, ४.

उरुऽचक्षसः ६. ५१, ९.

उरुऽचक्षसं १. २५, ५; १६.

उरुऽचक्षसा ८. १०१, २.

उरुऽचक्षाः ७. ३५, ८; ६३, ४.

उरुऽज्रयः ८. ७०, ४.

उरुऽज्रयः ७. ३९, ३.

उरुऽज्रयसं ५. ८, ६; ८. ६, २७.

उरुणा ४. २६, ५; ६. २४, ९.

उरुधाराऽइव ८. ९३, ३; ९. ६९, १.

उरुधारां ८. १, १०.

उरुऽनसौ १०. १४, १२.

उरुब्जं ९. ७७, ४.

उरुऽभिः १०. ७, १.

उरुऽयुगे ८. ९८, ९.

उरुऽलोकं १०. १२८, २.

उरुं १. २४, ८; ५७, ६; ९३, ६; २. ३२, १; ३. ४१, ५; ४६, ४; ५. १५, ५; ६. २३, ७; ४७, ८; ७. ३३, ५; ६०, ९; ८४, २; ९९, ४; ८. ६५, ३; ६८, १३[३]; ९. ८५, ४; १०. ४७, ३.

उरुव्यचःऽतमं ८. २६, १४.

उरुऽव्यचसं ६. ३६, ३: ८. २, ५; १०. १८, १०.
उरुऽव्यचसा १. १६०, २.
उरुऽव्यचसे ७. ३१, ११.
उरुऽव्यचा १. १०८, २.
उरुऽव्यचाः १. १०४, ९; ३. ५०, १; ५. ४६, ६; १०. १२८, ८.
उरुऽव्यंचे ५. १, १२.
उरुऽव्रजे ८. ६७, १२.
उरुऽशंस १. २४, ११.
उरुऽशंस १. १३८, ३; ८. ४८, ४.
उरुऽशंसः ४. १६, १८.
उरुऽशंसस्य २. २८, ३.
उरुऽशंसा ३. ६२, १७.
उरुऽशंसाः २. २७, ९.
उरुऽशंसाय १. ३१, १४; २. ३८, ११.
उरुषुं १. १५४, २.
उरुष्य १. ५८, ९; ९१, १५; ५. २४, ३; ८. ७१, ७; १०. ७, १.
उरुष्य १. ५८, ८; ४. २, ६; ११.
उरुष्यत् ३. ५, ८.
उरुष्यत् १०. ८०, ३.
उरुष्यत ५. ८७, ६; ८. २५, ११; ४७, ८.
उरुष्यतं ४. ४३, ४; ७.
उरुष्यतं ५. ६५, ६; ८. १०१, ४.
उरुष्यता ८. २५, १०.
उरुष्यतां ७. ८५, १; १०. ९३, ६.
उरुष्यति २. २६, ४; ६. १४, ५.
उरुष्यति १. १५५, २; १०. १७६, ४.
उरुष्यतु ८. ४७, ९.
उरुष्यथः १. १५५, २.
उरुष्यथः १. ११९, ६; १०. ४०, ८.
उरुष्यंतु ८. २५, १०.
उरुष्यवः ८. ४८, ५.
उरुष्या ६. ४४, ७.
उरुष्याः ७. ३, ८.
उरुष्यात् ७. १, १५.
उरुष्येत् १. १५२, ६; १५८, ४; ४. ५५, ५.
उरुऽसां ५. ४४, ६.
उरूचि ८. ६७, १२.
उरूची १. २, ३; ३. ३१, ११; ५७, ५; ७. ३५, ३.
उरूची इति ४. ५६, ४; ६. ११, ४.
उरूचीं ७. ४५, ३.
उरोः १. २५, ९; ३. ४६, ३; ५. ३८, १; ६. ७५, १८; ७. ६१, ३; ९. ९६, ३.
उरौ २. २७, १६; ३. १, ११: ६, ८; ५४, ९; ५. ४२, १७; ५२, ७; ७. ३९, ३; ८. ९८, ९: ९. ९७, १६; १०. ७०, ६: १३१, १.
उर्वरा ८. ९१, ६.
उर्वराऽजितें २. २१, १.
उर्वराणां १०. १४२, ३.
उर्वराऽपते ८. २१, ३.
उर्वरां ८. ९१, ५.
उर्वराऽसां ४. ३८, १; ६. २०, १.
उर्वरासु १. १२७, ६; ४. ४१, ६; ५. ३३, ४; ६. २५, ४; १०. ५०, ३.
उर्वशी ५. ४१, १९; १०. ९५, १०.
उर्वशीः ४. २, १८.
उर्वशीं १०. ९५, १७.
उर्वश्याः ७. ३३, ११.
उर्वारुकंऽइव ७. ५९, १२.
उर्विऽऊतिः ६. २४, २.
उर्विया १. ९२, ९; १२; ११३, ५; १२४, १; १४१, ५; २. ३, ५; ३५, ८; ३. १, १८; ५. २८, १; ४५, ९; ५५, २; ६. ६, ४; ३०, २; ६४, २; ३; ७. १७, १; ८. ८६, ५; १०. १०, २; ४५, ८; ६९, २; ९२, १२; ११०, ५: ११३, १०.
उर्वी १. २४, ९; १८९, २; ६. ४७, २०; ७. ३६, १; ८. ८०, ८; ९. ७४, ३.
उर्वी इति १. ६१, ८; १८५, ६; ७; ३. ६, १०; ३८, ३; ५६, ७; ४. ४२, ३; ५६, ३; ६. १०, ४; ६७, ५; ६८, ४; ९; ७०, १; ४; ७. १२, १; १८, २४; ३४, २४; ५७, १; ८६, १; १०. १२, ३; ८८, १४; ९३, १; १७८, २.
उर्वीः १. ८, ७; ३. ३३, ६; ६. ४७, ३; १०. १४, १६; ७९, ३.
उर्व्याः १०. १२८, ५.
उर्वी २. ४, ७; ३. ३३, ३: ५. ६२, ५: ६६, ३; ६. १७, ७; ७. ३८, २: ७७, ४; ९. ७८, ५; ८५, ८.
उर्व्याः १. १४६, २.
उलपस्य १०. १४२, ३.
उलूकः १०. १६५, ४.
उलूकऽयातुं ७. १०४, २२.
उलूखल १. २८, ५.
उलूखलक १. २८, ५.
उलूखलऽसुतानां १. २८, १–४.
उल्काः ४. ४, २.
उल्काऽइव १०. ६८, ४.
उल्बं १०. ५१, १.
उवाच १. ११६, १२; ७. ८७, ४.
उवाच २. ३०, २; ५. २, ८; ७. ९८, ३.
उवास १. ४८, ३.
उवास १. ११३, १३; १०. ११, ३.
उवाह १. ११६, १८.
उवे १०. ८६, ७.
उवोच ७. ४, ३.
उवोच ७. २०, ४; २१, १.
उवोचिथ ७. ३७, ३.
उशतः १. १२, ४; ७१, ६; २. ३७, ६; ६. ४, १; ७. १७, २; ३९, ४; १०३, ३; ८. ६०, ४; १०. १, ७; २, १; १६, १२; ७०, ४.
उशता ६. ४०, ४; १०. १६०, ३.
उशतां १०. ११, ३.
उशती १. १०९, ४; १२४, ७; ५. ४३, ११; ९. ९३, ४; १०. ८५, ३७.
उशती इति ३. ३३, १.
उशती इति १०. ७०, ६.
उशतीऽइव ५. ३२, १०.
उशतीः १. २२, ९; ६२, ११; ७१, १; १२४, १३; १४५, ४; २. ४, ३, ५. ४६, ७; ७. १०, १; १७, २; ९. ९५, ३; १०. ३०, २; ६; १५; ४३, १; ७०, ५.
उशतीःऽइव १०. ९, २; १११, १०.
उशतीं ६. ४७, ३.
उशते ३. ४३, ७; ४, १७, १७; २४,

६; ७. ९३, १; ९. ९७, ४६; १०. ९१, १३.
उशत्ऽभिः १०. १५, ८.
उशतऽभ्यः १. १६२, ११.
उशधक् ३. ६, ७; ३४, ३; ७. ७, २.
उशन् १. १०१, १०; २. ३६, ४; ३७, ६; ४. २०, ४; २५, १; ६. ४, १; १०, ६; ७. ९८, २; १०. १५, ८; १६, १२; ३०, ६; ७०, ९.
उशना १. ५१, १०; ८३, ५; १२१, १२; १३०, ९; ४. २६, १; ५. २९, ९; ३१, ८; ३४, २; ८. ७, २६; २३, १७; ९. ८७, ३; १०. २२, ६.
उशनाऽइव ४. १६, २; ९. ९७, ७.
उशना १०. ४०, ७.
उशने १. ५१, ११; ६. २०, ११.
उशंतः ८. ९३, २२; १०. १६, १२²; ७०, ६; ८५, ३७.
उशंतः १०. ३०, २.
उशंते १. ६२, ११; ७१, १; २. ११, ६; ३. ५, ७; ४. २२, ३; ९. ६८, ६; ९५, ३; १०. ११, ३.
उशंता ७. ४२, ५; ९१, २.
उशंति १. २, ४; १०. १०, ३.
उशंति ९. ९६, ४.
उशमानः ४. १९, ४.
उशानः ३. ५, ७; ४. २३, १; ६. ३९, २.
उशिक् १. ६०, ४; ३. ३, ७; ११, २; १०. ४५, ७.
उशिक्ऽभिः १. १८९, ७; ३. ३४, ४.
उशिक्ऽभ्यः २. ४, ५.
उशिजः १. ६०, २; १३१, ५; २. २१, ५; ३. २, ९; १५, ३; ६०, १; ४. १, १५; ६, ११; १६, ६; ७. १०, २; ५; ९०, ४; ९. ८६, ३०; १०. ४६, २; १०४, ४.
उशिजे ३. २, ४; ३, ८; २७, १०.
उशिजा १. १२८, १; १०. ९२, १२.
उशिजाऽइव २. ३१, ६.
उशीनराण्याः १०. ५९, १०.
उशोन्यः ७. ३, ९.
उश्मसि १. ३०, १२; ८६, १०; ९४, ३; ८. ४५, २०; १०. ३८, २; ७४, ६.
उश्मसि १. २१, १; २२, ६; १२९, ४; १५४, ६; ५. ७८, ३; ८. ८०, ९; ९. ३१, ६; ६६, १४; १०. ३९, २; ४०, ११.
उषः १. ४८, ४; ९; ११; १२; १४; १५; ४९, १; ३; ५७, ३; ९२, ७; ८; १३; १४; ११३, ७; ९; १२३, ३; ५; १३; १२४, १२; ३. ६१, १–३; ४. ५२, ६; ७; ५५, ९; ५. ७९, १; ६; ७; ६. ६४, २; ७. ७५, २; ८; ७६, ३; ६; ७७, ५; ६; ७८, १; ८१, ३; ५; ८. ४७, १६; १८; १०. ९५, ४; १२७, ७.
उषः १. ६९, १; ५; ३. ६, ७; ७. १०, १; ८. ४१, ३.
उषः १. ३०, २०; ४८, १; २; १२; १६; ४९, २; ४; ९२, १५; ११३, १२; १२३, ११; १२४, १०; ४. ५२, ३; ५. ७९, १०; ६. ६५, ५; ७. ७९, ४; ८१, २; ८. ९, १७; १८; १०. ५५, ४.
उषःऽउषः १०. ८, ४.
उषःऽबुधः १. १४, ९; ४४, १; ९; ९२, १८; १३२, २; ४. ४५, ४; ७. ७६, ६.
उषःऽबुधं ३. २, १४; ४. ६, ८; ६. १५, १; ९. ८४, ४.
उषःऽबुधे १. १२७, १०.
उषःऽभुत् १. ६५, ५; ६. ४, २.
उषत्ऽभिः १. ६, ३.
उषमाणः ४. २२, २.
उषसः १. ३४, ३; १०; ४४, १; १०; ७९, १; ६; ९०, ७; ९२, १; २; ९४, ५; ११३, १७; १८; २०; ११८, ११; १२१, ६; १२३, ६; ११; १२; १२४, ९; १३१, ६; १३४, ३²; ४; १३७, २; १५१, ५; १७९, १; १८०, १; २. २, २; ७; ८; १५, ६; २०, ५; २१, ४; २८, ९; ३४, १२; ३. ५, १; २; ७, १०; १५, २; १७, ३; ३०, १३; ३१, ४; ५५, १; ५८, १; ४. १, ५; १३; १७; २, १५; १९; ५, १३; १४, ४; १९, ८; २३, ५; ७; ३९, १; ३; ४०, १²; २; ४५, २; ५१, १–३; ६–९; ५. ३७, १; ४५, १; ५९, ८; ६२, ८; ८१, २; ६. १५, ५; २८, १; ३८, ४; ३९, ३; ४४, २३; ५०, ८; ५२, ४; ६०, २²; ६४, १; ६५, २; ७. ६, ५; १८, २०; ३५, १०; ३९, २; ४१, ६; ७; ६७, २; ६९, ५; ७१, १; ७२, ३; ४; ७५, ३; ७६, २; ७८, ३; ७९, २; ८८, ४; ९०, ४; ८. ९६, १; ९. १०, ५; ७१, ७; ७५, ३; ८३, ३; ८६, १९; २१; ९०, ४; १०. ६, ३; २९, २; ३१, ७; ३५, १; ५; ६; ३९, १; ४१, १; ७३, ६; ८८, १२; १८; १९; ८९, १२; ९२, २; १११, ७; १२२, ७; १३८, १.
उषसः १. १२४, १३; ४. ५१, ४; ५; ११; ६. ६५, ३; ४; ७. ७८, ५.
उषसे १. ३२, ४; ४४, ८; ५६, ४; ७१, १; ११३, ११; ११५, २; २. १२, ७; ३. २०, १; ५; ३१, १५; ३२, ८; ४४, २; ६१, ५; ६; ४. ३, ११; १२, २; ३०, ९; ५. १, १; ५, ६; २८, १; ८०, १; ६. १७, ५; ३०, ५; ७२, २; ७. ३३, ७; ४४, १; ३; ७५, ६; ७; ७६, ४; ७८, ४; ८०, १; ८५, १; ९१, १; ९९, ४; ८. ५, २; ९. ८४, २; १०. ३५, २; ५८, ८; ६४, ३; ६५, १०; ६७, ५; १२७, ३.
उषसा १. ४४, २; १४; ६२, ५; ७३, ७; १८३, २; ३. १४, ३; ५. १, ४; ५१, ८; ८. ४२, ५; ४४, ४; ८. २७, २; ३५, १.
उषसानक्ता १. १२२, २; १८६, ४;

२. ३, ६; ३१, ५; ४. ५५, ३; ५. ४१, ७; ७. २, ६; १०. ३६, १; ७०, ६.

उपसां २. २८, २; ३. ६१, ७; ४. १३, १; ५. ७६, १; ६. ४७, ५; ७. ५, ५; ८, १; ९, १; ३; १०, २; ६३, ३; ६८, ९; ८. १९, ३१; १०. १, १; ४५, ५; ७८, ७; ८५, १९; ९१, ५; ९५, २.

उपसांऽइव ८. ४३, ५; १०. ३१, ५; ९१, ४.

उपसि १. १८४, १; २. ८, ३; ४. २, ८; ७. ३, ५; ८. २२, १४.

उपसे १. ११३, १.

उपसौ १. १८८, ६; ३. ४, ६.

उपाः १. ४६, १; १४; ४८, ३; ५; ७; ८; १३; ६२, ८; ९२, ४; ६; ११३, ४–६; ८; १३–१५; १२३, २; ७; १२४, १; २; ७; १५७, १; २. ३४, १२; ३. ६१, ४; ४. १४, ३; ३०, १०; ५२, २; ५; ५. ७५, ९; ८०, २; ५; ७. ७५, १; ५; ७६, १; ७; ७७, ३; ७८, २; ७९, ३; ८०, २; ८१, ६; ८. ५८, २; ७३, १६; ९. ४१, ५; १०. ११, ३; ३५, ३; १३८, ५; १७२, ४.

उपाःऽइव १०. १३४, १.

उपाणः ४. १६, १४.

उपां १. १८१, ९; १०. ६८, ९.

उष्टारांऽइव १०. १०६, २.

उष्ट्रः १. १३८, २.

उष्ट्रान् ८. ६, ४८; ४६, ३१.

उष्ट्रानां ८. ५, ३७; ४६, २२.

उष्णन् २. ४, ७; ९. ९७, ३९.

उष्णंऽइव १०. ४, २.

उष्णिहया १०. १३०, ४.

उष्णिहाभ्यः १०. १६३, २.

उस्रः १. ६९, ५; ३. ५८, ४; ५. ४९, ३; ६. १२, ४; ७. १५, ८; ८. ४१, ३.

उस्रयः ९. ६५, १; ६७, ९.

उस्रऽयामा ७. ७१, ४.

उस्रऽयाम्णे ४. ३२, २४.

उस्रा ४. ४५, ५; ६. ६२, १; ७. ७४, १; ९. ५८, २; १०. ३५, ४.

उस्रा २. ३९, ३.

उस्राऽइव १. ९२, ४.

उस्राः १. ७१, २; १२२, १४; १७१, ५; ४. १, १३; २५, २; ६. ३, ६; ३९, २; ५२, १५; ७. ६९, ५; ८. ४६, २६; ७५, ८; १०. ३५, ८; ६७, ४; १३८, २; १६९, १; १७५, २.

उस्राःऽइव १. ३, ८; ८७, १; २. २३, २; ८. ९६, ८.

उस्राणां ८. ४१, ५.

उस्रां १०. ६, ५.

उस्रि ५. ५३, १४.

उस्रिकं १. १९०, ५.

उस्रियः ५. ५८, ६; ९. ७०, ६; ७४, ३.

उस्रियं ८. ४, १६.

उस्रिया ४. ५, ९.

उस्रियाः १. ६, ५; ९३, १२; ११२, १२; ३. १, १२; ३१, ११; ४. ५०, ५; ७. ८१, २; ९. ६८, १; १०८, ६; १०. ६७, ८; ६८, ७.

उस्रियाणां १. १२१, ४; ४. ५, ८; ५. ३०, ४; ११; ६. ३२, २; ७. ७५, ७; १०. ६८, ६.

उस्रियाभिः १. ६२, ३; ९. ९३, २; ९६, १४.

उस्रियाभ्यः ६. १७, ६.

उस्रियायाः १. १२१, ५; १५३, ४; १०. ६१, २६; ८७, १७.

उस्रियायां १. १८०, ३; ३. ३०, १४; ३९, ६.

उस्रियासु २. ४०, २; ५. ८५, २.

उहानाः ८. ४०, ८.

उहीत ७. ३७, ६.

उहुवः ४. ४५, ४.

उह्यते १०. ८५, १३.

उह्यमानः २. १८, ६.

ऊ

ऊखयंते १०, ९४, ३.

ऊचिम १. १६१, १.

ऊचिषे ३. २२, ३.

ऊचुः ६. ४५, ८.

ऊचुः ४. ३३, ६.

ऊचुषे १. १०३, ४; १०. ३३, ६.

ऊचे १०. ४०, ५.

ऊतयः १. ८, ९; ११, ३; ५१, २; ५२, ४; ५; ९; ८४, २०; ९१, ९; १००, ७; ११९, २; १३४, २; १६७, १; ३. १३, २; १४, ६; ४. ३१, १०; ५. ५४, ७; ६. २४, ३; ३६, ३; ४४, ६; ४५, ३; ७. २५, ३; २६, ४; ८. ४६, ७; ४७, १^{२}; ६६, १२.

ऊतये १. ४, १; ८, १; ९, ९; २२, ५; २३, ३; ३०, ६; ७; ३५, १; ३६, १३; ४५, ४; ४८, १४; ५६, ४; १०४, २; १०५, १७; १०६, १; ६; १११, ४; १२९, ४; १३०, ९; १४४, ५; २. ५, १; ३२, ८; ३४, १४; ३. ९, १; १४, २; २७, ६; ३०, २२; ३७, ८; ४. ३२, २; ४४, ३; ४७, ३; ५. ५, ३; ५; ८, १; १०, ६; १३, १; १७, १; २०, ४; २२, ३; ४६, ३; ६. ९, ७^{२}; २१, ९; ७. २६, ५; ४४, १; ९४, ५; ८. १, ३; ४; ५, ४; ६, २७; ४४; ७, ६; ११, ६; १२, १४; १५; १५, १२; २१, २; ९; २२, १; ३२, ४; १०; ३४, ६; ३८, ९; ४५, १७; ५०, ४; ६०, १८; ६६, १; ६८, १; ५; ७१, १०; ८३, १; ८८, ४; ९२, ७; ९. ५१, ४; ६२, ७; ६५, १७; ६६, ४; १०. ४३, १; ६१, २७; ६३, ११; ६४, ८; ६६, ९; ८१, ७; १०१, ९; १२; १२६, ३; ७.

ऊतिः १. ६३, ६; ११७, १९; २. ३४, १५; ६. २५, १; ७. ५९, ४.

ऊतिऽभिः १. ७, ४; २३, ६; ३०, ८; ३९, ८; ९; ४६, १५; ५३, १०; ७९, ७; ८३, १; ११२, १–२३; १२९, ५^{२}; १८७, ३; २. ८, ६;

११, १९; २३, १; ३१, ३; ३. १, १९; ३६, १; ५३, २१; ४. १६, ९; ३१, ३; १२; १३; ३२, १; ५; ४१, १०; ५. ९, ६; ३३, ७; ४०, ३; ४२, ८; ६. ८, ६; १०, ३; १९, ८; ४४, ३; ७. १९, ३; २४, ४; ५८, ३; ८४, ३; ८. ५, २४; ८, १; १८; १२, ५; १३, १७; २४; २५; १९, २८; ३०; २०, २४; २२, १६; २४, ११; ३२, १२; ३७, १; ४८, १५; ५३, ५; ८; ६१, ५; १३; ६७, १६; ७०, ६; ९५, ८; ९७, ११; १०२, १५; ९. ४, ५; ५२, ५; ६२, २५; १०. ४९, ३; १३४, ३; ४.

ऊतिं १. १०, १०; ८. १४, ६; १०. १०४, ५.

ऊतिपु ८. २०, १५.

ऊती १. ६४, १३; १००, १–१५; १२९, ८; १३६, ६; ७; १५८, १; १७२, १; १७८, १; २. ११, १३; १२, १४; १७, ८; २०, २; ३; ३. २५, ५; ४. १, ५; २३, २; २५, २; २९, १; ४; ३१, १; ३४, ९; ४१, ११; ४३, ४; ५. ३०, १; ४३, १०; ६. २, ४; ५, ७; १०, ५; १९, १०; २३, ३; २४, ९; २६, ५; २९, ५; ६; ३३, ४; ४३, ४; ४५, १७; ७. १९, ११; २०, २; २५, १; २७, ४; ३७, ५; ५७, ७; ५९, ९; १०; ८. २१, ७; ६६, १४; ६८, ४; ७१, ५; ९७, ७; ९९, ७; ९. ९७, ३८; १०. १५, ४; ३५, १३; ६४, १; १०४, ४.

ऊती इति १. १८५, ९.

ऊतीः १. ११९, ८; १३०, ५; ८. ५, २३; १०. ६, ६.

ऊत्या १. १३५, ५; ६. ४८, ९; ८. १८, ७; ९३, १९; १०. १५६, २.

ऊदिम १. १६१, १.

ऊर्धः १. ६४, ५; ६९, २; १४६, २; २. १४, १०; ३४, १०; ३. १, ९; ४८, ३; ५५, १३; ४. १, १९; ३, १०; २३, १; ५. ३२, २; ४४, १३; ६. ६६, १; ७. ५६, ४; १०१, १; ८. २, १२; ३१, ९; ९. ९३, ३; १०७, ५; १०. ५, १; २०, २; ३०, ११; ३१, ११; ३२, ८; ६१, ९; ७३, ९; ७६, ७; १००, ११.

ऊर्धःऽसु १०. ४९, १०.

ऊर्धन् १. १५२, ६; १८६, ४; ४. ७, ७; १०, ८; ७. ३६, ३; १०. ४५, ३.

ऊर्धनि १. ५२, ३; २. ३४, २; ६; ३. २९, १४; ५. ३४, ३; ९. ६९, १; ७१, ४; १०७, २०; १०. १७९, ३.

ऊर्धऽभिः ८. ९, १९; ९. ६८, १; १०. १७२, १.

ऊध्नः ४. २२, ६.

ऊनयीः १. ५३, ३.

ऊपर्थुः १. ११६, ११.

ऊपथुः १. ११७, ५; १२; १०. ३९, ८.

ऊपिपे १. ३१, ९.

ऊपे १०. ६८, ३.

ऊं इति १. २४, ८; २६, ५; २७, ४; २८, १–४; ३०, २; ४; ३२, १५; ३४, ६; ३५, ६; ३६, १३; ३७, १०; ४५, ५; ४६, १०[२]; ११; ५०, १; ५२, ८; ५३, १; ६१, १–८; ११–१५; ६२, ६; ७७, २; ७८, २–४; ८०, ७; ८२, ६; ९१, १८; ९२, १; ९३, ६; १०५, २; १०८, ४; ११०, १[२]; ११२, १–२३; ११३, २; ४; ५; ११; ११६, १७; १२३, ८; १२४, ५; १३८, ४; १३९, ४; १४०, ४; ११; १४३, ७; १५४, ४; १५६, १–३; १६१, १; १६२, २१; १६४, ५; १६; १९[२]; २६; २८; ४८; १६८, १; १७३, ५; १७८, ५; १७९, १; २; १८१, १; १८४, २; १९१, ५; २. २, ५; ३, ११; ५, ३; ६, १; ८, ३; ९, २; १८, २; २०, ४; २४, ६; ११[२]; २९, ३; ३०, ६; ३३, ९; ३५, ३; १०; १५; ३७, २[२]; ३८, १; ४१, ७; ३. १, ३; २, ९[२]; ४, १०; ५, २; ३; ९; ८, ४; २०, २; २४, ४; २९, ८; ३१, ७; ११; ३२, १५; ३६, १; ३७, ११; ३८, २; ४६, ५[२]; ५१, ४; ५३, ४; २१[२]; ५४, ७; ५७, ४; ६२, १; २; ४. २, ४; ३, २; ५, ३; ९; ११; ६, ३; ११; ७, ९; ८, ४; ९, ६; १७, १७; १८, ७; २०, ४; २१, ४; ९[२]; २२, ७; २३, १०; ३४, ४; ३६, २; ३८, २; ३९, १; ५; ४०, १; ४३, १; २; ६; ५१, १; २[२]; ५५, ४; ५८, ९; ५. १, ६; २, १०; ४, ११; १७, ३; २९, २; १३; ३०, १५; ३१, ४; ३४, ४; ३९, ५; ४२, ११; ४४, ८; १४; ४८, १; ५५, ७; ५८, १; ७३, ४; ८; ९; ७४, ९; १०; ८३, १०[२]; ८५, ५; ६; ६. १, १०; ७, ६; ९, ६; १०, २; १५, १; १२; १७; १९; १६, १४–१६; २१, १; १०; २२, २; २३, ३; ७; २४, ५; ९; २५, १; २७, १[२]; ७; २९, १; ३८, १; ४०, २; ४४, ४; १४; ४५, ६; १०; १३; २५; २८; ५१, १; ३; १०; ५३, १; ५४, २; ६४, १[२]; ७१, ५; ६; ७३, २; ७. ४, ८; ८, २; ३; १७, ६; १८, ३; १७; २०, २; ५; २१, २; २३, १; २९, २; ३०, २; ३३, ५; ३५, २[२]; ३; ७[२]; ८; ९[२]; ११; १२; ३८, २; ४२, ३; ४४, २; ५; ६०, ९; ६१, ६; ६३, १; ६६, १४; ६७, ५; ६८, ४; ७२, ३; ७३, २; ७६, १; २; ८१, १; ८४, २; ८५, २; ८६, ८; ८८, २; ९३, ६; ९५, ६; ९६, १; ९७, ३; ९९, ४; १०१, ३[२]; १०४, १३; २०; २१; ८. २, १३; १७; ३, ३; १४[२]; १५; २०; ७, ६; ७; १७[२]; १९; २२[२]; ९, १६; १५, १; ४; १७, ७; २०, १९; २१, १; ९; २२, १३; २३, ५; ७; १३;

१६; २४, १; १६; २६; २५, १९; २६, १; २७, १२; ३०, ३; ४०, ३; ४१, १; २; ४३, २४; ४४, ९; ४५, १६; २८; ३३; ४६, २७; ४७, ७; ४८, ३; ५२, १०; ६१, ५; १२; ६२, १२; ६३, ५; ८; ६४, ६; ८; ९; ६५, ५; ६६, ७; ९; १०[२]; १३; ६९, १४; ७०, ९[२]; ७५, ७; ८०, १०; ८१, ८; ८२, ३; ८४, ५; ९०, ६; ९२, ४; ७; १२; ९३, १५; ९५, ६; ९६, ५; ६; १००, ३; १०३, १०; **९.** २, ८; ३, १०; १५, ८; १७, ७; २१, ७; ३८, १; ४५, ४; ६१, ७; २०; ६६, ८; ८६, २१; ९२, ५; ९७, ३; १०१, ८; १०७, ८; १०८, ११; ११०, १; ११२, १; **१०.** १, ४; २, ३; १०, ६; ११; १२; १४[२]; १३, २; १४, २; १५, १३; १६, ४; ११; १३; १७, २; २१, २; २५, ४; २७, ५; ६; ७[२]; १०; २९, ४; ३०, ७; १५; ३१, ४; ७; ३२, ८; ३५, १; ३८, ५; ३९, १; ४०, ११; ४१, १; ४८, ७; ५२, ३; ५४, ३; ५६, १; ६१, २४; २७; ६५, १०; ६९, २; ७१, ७[२]; ८; ११; ७२, ४; ७६, २; ८१, ४; ८५, ४७; ८६, ३; १३; ८८, ६; १०; १८; ९२, १४; ९४, ८; ९५, १४; १५; १८; १०२, १०; १०३, ११; १०४, १०; १०६, १; १०७, ६; ११४, ४; ११७, १; १२४, ५; १२५, ६; १२६, ३[२]; ६; १२७, ३[२]; १३०, २; १३२, ३; १३३, १; १३७, ६; १४२, ३; १४९, ३; १५०, ३; १६०, २; ५; १६१, ४; १६७, १; ३; १७३, २; ३; १७६, ३; १७८, १; १८०, ३; १८२, ३.

ऊर्माः **३.** ६, ८; **४.** १९, १; **५.** ५२, १२; **७.** ३९, ४; **१०.** ६, ७; ३१, ३; १२०, १; ३.

ऊर्मासः **१.** १६६, ३.

ऊर्मिभिः **५.** ५१, १.

ऊर्मिभ्यः **१०.** ३२, ५.

ऊर्मैः **१.** १६९, ७.

ऊरुः **८.** १, ३४.

ऊरुभ्यां **१०.** १६३, ४.

ऊरुं **१०.** १८०, ३.

ऊरू इति **१०.** ८५, ३७; ९०, ११; १२; १६२, ४.

ऊर्जेऽअदः **१०.** ५३, ४.

ऊर्जः **१.** ५८, ८; **२.** ६, २; ११, १; **५.** १७, ५; **६.** १६, २५; **८.** ७१, ३; ९; ८४, ४; **१०.** २०, १०; ११५, ८; १४०, ३.

ऊर्जः **१.** ९६, ३; **३.** २७, १२; **४.** ३९, ४; **५.** ७, १; **६.** ४८, २; **७.** १६, १; १७, ६; **८.** १९, ४; ४४, १३; ६०, २; **१०.** ४४, ४.

ऊर्जं **१.** ६३, ८; ९२, १७; ११६, ८; ११८, ७; १५७, ४; **२.** ११, १३; १९, ८; २२, ४; **४.** ४०, २; **५.** ७६, ४; **६.** ४, ४; ६२, ४; ६५, ३; ७०, ६; **७.** ४९, ४; **८.** ८, १६; ३५, १०; ५४, १; ७२, १६; ९३, २८; १००, १०; ११; **९.** ६३, २; ६४, १४; ६६, १९; ८०, ३; ८६, ३५; ९४, ५; **१०.** १५, ७; २०, १०; १००, १०; १०९, ७; १६५, ५.

ऊर्जयन् **२.** ३५, ७.

ऊर्जयंति **९.** ८९, ४.

ऊर्जयंतीः **३.** ७, ४; **७.** ६५, २.

ऊर्जयंतीं **५.** ४१, १८; **१०.** ९७, ७.

ऊर्जयंत्याः **२.** १३, ८.

ऊर्जयमानं **१०.** ३७, ११.

ऊर्जव्यस्य **५.** ४१, २०.

ऊर्जेऽसने **६.** ४, ४.

ऊर्जस्वतीः **१०.** १६९, १.

ऊर्जस्वंतः **१०.** ५१, ९.

ऊर्जस्वंतं **१०.** ५१, ८.

ऊर्जा **३.** ३, ७; **४.** ४०, ३; **८.** ३६, ३; **१०.** १९, ७; २६, ९; १०६, १०.

ऊर्जाऽआहुतिः **८.** ३९, ४.

ऊर्जानां **१.** ११९, २.

ऊर्जां **१.** १२८, २; **५.** ४१, १२; **१०.** ७६, १.

ऊर्जां **१.** २६, १; **८.** १९, ७; २३, १२; ६०, ९.

ऊर्जे **९.** ४९, ४; **१०.** ९, १.

ऊर्णऽम्रदाः **५.** ५, ४; **१०.** १८, १०.

ऊर्णाः **५.** ५२, ९.

ऊर्णा **४.** २२, २.

ऊर्णाऽवती **१०.** ७५, ८.

ऊर्णाऽवतीनां **८.** ५६, ३.

ऊर्णाऽवंतं **६.** १५, १६.

ऊर्णु **९.** ९६, ११.

ऊर्णुत **२.** १४, ३.

ऊर्णुते **१.** ९२, ४; **२.** ३४, १२; **८.** ३९, ६; **९.** ११०, ६.

ऊर्णुथः **१०.** ४०, ८.

ऊर्णुषे **४.** ५४, २.

ऊर्णुष्व **१०.** १६, ७.

ऊर्णुहि **१०.** ७३, ११.

ऊर्णुहि **९.** ९१, ४; **१०.** १८, ११; ३८, २.

ऊर्णोत् **१.** ६८, १.

ऊर्णोति **१.** १०५, १५; **८.** ७९, २; **१०.** ८८, १२.

ऊर्दरं **२.** १४, ११.

ऊर्ध्वः **१.** २८, १; ३०, ६; ३६, १३[२]; १४; ९५, ५; १६४, १०; **२.** २०, ६; ३०, ३; ३५, ९; ३८, २; **३.** ४, ४; ८, १; ४९, ४; **४.** ४, ५; ६, ४; **५.** १, २; ३; **६.** २४, ९; ६३, ४; **७.** ३९, १; ६८, ४; **८.** १९, १०; २७, १२; **९.** ८५, १२; ९८, ३; **१०.** १, १; २०, ५; ७०, १; ७; ९०, ४; १००, ९.

ऊर्ध्वऽकृशनं **१०.** १४४, २.

ऊर्ध्वऽग्रावाणः **३.** ५४, १२.

ऊर्ध्वऽथा **१०.** २३, १.

ऊर्ध्वं **१.** २४, ७; ८५, १०; ८८, ४; **३.** ८, ८; ३१, १२; ६१, ५; **४.** ६, २; १३, २; १४, २; **७.** २, ७; **१०.** ३, २.

ऊर्ध्वया **१.** १२७, १.

ऊर्ध्वेऽशोचिषं ६. १५, २.

ऊर्ध्वसानः १०. ९९, ७.

ऊर्ध्वेऽसानुः १. १५२, ५.

ऊर्ध्वा १. ८८, ३; ११९, २; १३४, १; १७१, ३; ३. ४, ४; ५५, १४; ६१, ३; ७. ४३, २; ८. ४५, १२; ९. ८८, २; १०. ६१, २०; १०५, ९.

ऊर्ध्वाऽईव ५. ८०, ५.

ऊर्ध्वाः १. १४०, ८; १८१, ६; ३. ५७, ४; ५८, २; ७. ७८, १; १०. ९२, १५.

ऊर्ध्वान् १. ३६, १४; १७२, ३.

ऊर्ध्वां १. १४४, १; ७. ६४, ४; १०. २७, १३.

ऊर्ध्वासः ७. ३१, ९; १०. ११५, ९.

ऊर्मयः १. ४४, १२; ५२, ७; १६८, २; ४. ५८, ६; ६. ४४, २०; ६४, १; ७. ९६, ५; ८. १०३, ११; ९. ७, ८; ३३, १; ६१, ५; ८१, १; ८६, २; ९५, ३; १०. ६८, १.

ऊर्मा ९. १२, ३; २१, ३; ३९, ४; ८५, १०.

ऊर्मिः २. १६, ५; ३. ३३, १३; ४. ५८, १; ६. ४७, १४; ८. १४, १०; ७५, ९; ९. ६४, ११; ७८, २; ८०, ५; ८६, ४०; १०८, ५; ११०, ११; १०. १४८, ५.

ऊर्मिणे ९. ९८, ६.

ऊर्मिणा ९. ६८, ८; ७४, ५; ७६, ३; ८६, १३; २५; १०६, १०; १०७, १५.

ऊर्मिऽभिः १. ९५, १०; ३. ३३, २; ४. ५८, ७; ६. ६१, २; १०. ६४, ९.

ऊर्मिं १. ९५, १०; ३. ४७, १; ४. ५७; २; ५८, ११; ६. १७, १२; ४१, २; ७. ४७, १; २; ४; ८. ५९, ३; ९. ४४, १; ४९, १; ८६, ८; ८८, ५; ९६, ७; ८; १९; १०. ३०, २; ३; ७–९; १२३, २.

ऊर्मीन् ४. १९, ५.

ऊर्मेःऽईव ९. ५०, १.

ऊर्मौ १. २७, ६; ९. १४, १; ७२, ७; ७३, २.

ऊर्म्या १. १८४, २.

ऊर्म्याः २. ४, ३; ८. ९६, १.

ऊर्म्यायाः ६. १०, ४; ६५, २.

ऊर्म्यासु ६. ४८, ६.

ऊर्म्ये ५. ६१, १७; १०. १२७, ६.

ऊर्वःऽईव ३. ३०, १९.

ऊर्वं १. ७२, ८; २. ३५, ३; ३. ३२, १६; ४. २, १७; २८, ५; ५०, २; ५. २९, १२; ३०, ४; ६. १७, १; ७. ९०, ४; १०. ७४, ४; १०८, ८.

ऊर्वस्यं ८. ६६, ३.

ऊर्वात् ४. १२, ५; ५. ४५, २; ६. १७, ६.

ऊर्वान् २. १३, ७; ७. १६, ७.

ऊर्वे ३. १, १४; ७. ७६, ५; ९. ८७, ८.

ऊर्वोः ८. ७०, १०.

ऊळहाः ६. ६०, २.

ऊर्वध्यं १. १६२, १०.

ऊवुरित्यूवुः १. ६१, ८.

ऊष ४. ५१, ४.

ऊषतुः १०. ४०, २.

ऊषुः ३. ७, १०.

ऊष्मण्या १. १६२, १३.

ऊहति ५. ३४, ३.

ऊहथुः १. ४७, ९; ११२, १९; ८. ३८, ५.

ऊहथुः १. ११६, ३–५; २०; ११७, ९; १४; १५; २०; १८२, ७; ६. ६२, ३; ६; ६३, ६; ७. ६९, ७; ८. २६, १५; १०. ३९, ४; ७; ६५, १२.

ऊहसि ८. २१, १४.

ऊहिरे २. ३४, १२; ८. १९, १.

ऊहिषे १. १२८, ६.

ऊहुः ४. २७, ३.

ऊहे ५. ३, ९.

ऊहे १. १८१, ४; १०. ५२, ३.

ऊह्याते १. १२०, ११.

ऊह्याथे इति ४. ५६, ६.

ऋ

ऋक्ऽभिः २. ३५, १२.

ऋक्वः १०. ३६, ५.

ऋक्वता ४. ५०, ५.

ऋक्वऽभिः १. ८७, ६; १५५, ६; ५. ५२, १; ६०, ८; ६. ३२, २; ३; ७. १०, ४; ८. ६३, ११; ९७, १२; ९. ६४, १९; १०७, ११; १११, $१^{२}$; १०. १४, ३; ६४, ४; ११३, ९.

ऋक्वा ७. ३७, ४; ९. ९१, ३.

ऋक्वाणः १. ८७, ५; ३. १३, ५.

ऋक्षः ५. ५६, ३.

ऋक्षस्य ८. ६८, १५.

ऋक्षाः १. २४, १०.

ऋक्षात् ८. २४, २७.

ऋक्ऽसामाभ्यां १०.८५, ११; ११४, ६.

ऋग्मिणः ९. ८६, ४६.

ऋग्मिऽभिः १. १००, ४.

ऋग्मियः ८. २३, ३; ९. ७४, ३.

ऋग्मियं १. ९, ९; ५१, १; ३. २, ४; ६. ८, ४; ४५, ७; ८. ३९, १; ४०, १०; ९. ६८, ६.

ऋग्मियायं १. ६२, १.

ऋग्मी १. १००, ४.

ऋघायतः २. २५, ३; ४. ३०, ५; ३८, ८; १०. ११३, ६.

ऋघायंते ४. १७, २.

ऋघायमाणः १. ६१, १३; १७६, १.

ऋघायमाणं १. १०, ८.

ऋघावत् १०. २७, ३.

ऋघावा ४. २४, ८.

ऋघावान् १. १५२, २; ३. ३०, ३.

ऋचः १. ३६, ११; ५. ४४, १४; १५; १०. ९०, ९; ९१, १२.

ऋचः १. १६४, ३९.

ऋचे ७. ६६, ११.

ऋचसे ६. ३९, ५; ७. ६१, ६.

ऋचा १. १६४, ३९; २. ३, ७; ५. ६, ५; २७, ४; ६४, १; ४; ८. २७, १; ५; ९. ७३, ५; १०. १०५, ८; १६५, ५.

ऋचां १०. ७१, ११.

ऋचीषम ६. ४६, ४; ८. ९२, ९.

ऋचीषमः ८. ३२, २६; ६२, ६; ९०, १; १०. २२, २.

ऋचीषमं ८. ६८, ६.

ऋचीषमाय १. ६१, १.

ऋच्छतु १०. १६४, ५[२].

ऋच्छंति १०. १०२, ६.

ऋच्छंतु १०. ८७, १५.

ऋच्यते ८. ३८, १०.

ऋच्यंते ७. ७०, ६.

ऋच्यमाना ६. ३८, २.

ऋच्यमाने इति ६. ४९, ३.

ऋजवः १०. ८५, २३.

ऋजवे २. २७, ९; ६. ७०, ३.

ऋजिप्यः ४. २७, ४; ३८, ७.

ऋजिप्यं ४. ३८, २; ६. ६७, ११.

ऋजिप्याः ३. ३१, १७.

ऋजिप्यासः २. ३४, ४.

ऋजिश्वना १. ५३, ८; १०१, १; १०. १३८, ३.

ऋजिश्वनि ८. ४९, १०.

ऋजिश्वने ४. १६, १३; ६. २०, ७.

ऋजिश्वा ५. २९, ११; १०. ९९, ११.

ऋजिश्वानं १. ५१, ५.

ऋजीतिः १०. २१, २.

ऋजीतिऽभिः १०. ७९, ७.

ऋजीती १०. ७५, ७.

ऋजीते ६. ७५, १२.

ऋजीपिन् ८. ३३, १२.

ऋजीपी ४. २६, ६.

ऋजीयः ७. १०४, १२.

ऋजीषं १. ३२, ६.

ऋजीषिणः १. ८७, १; २. ३४, १; ८. ३२, १.

ऋजीषिणं १. ६४, १२; ६. ४२, २; ८. ७६, ५; ८६, ४.

ऋजीषिन् ३. ३२, १; ३६, १०; ४३, ५; ५०, ३; ६. १७, १०; २०, २; ७. २४, ३; ८. ७९, ४; ९६, ९.

ऋजीषी ३. ४६, ३; ४. १६, १; ५; ५. ४०, ४; ६. १७, २; ३८, २; २४, १; ८. ९०, ५; १०. ८९, ५.

ऋजु २. ३, ७; ४. १, १७; ५. ४६, १; ६. ५१, २; ७. ६०, २; १०. ६७, २.

ऋजुऽअंचः ४. ६, ९.

ऋजुः २. २६, १; ९. ९७, ४३.

ऋजुऽक्रतुः १. ८१, ७.

ऋजुऽगाथ ५. ४४, ५.

ऋजुना १. ४१, ५.

ऋजुऽनीती १. ९०, १.

ऋजुं ९. ९७, १८.

ऋजुऽमुष्काः ४. ६, ९.

ऋजुऽमुष्कान् ४. २, २.

ऋजुऽयतां १. ८९, २.

ऋजुऽयते १. ११६, २३; ५. १२, ५; १०. १००, ३.

ऋजुऽयंत १. १३६, ५.

ऋजुऽयमानः १०. ८८, ९.

ऋजुऽयवः १. २०, ४.

ऋजुयाऽइव १. १८३, ५.

ऋजुऽवनिः ५. ४१, १५.

ऋजुऽहस्ता ५. ४१, १५.

ऋजूनसि ८. ५२, २.

ऋज्यते १. १४०, २.

ऋज्यंतः ६. ३७, २; ३.

ऋज्रऽअश्वः १. १००, १७; ११७, १८.

ऋज्रऽअश्वं १. ११६, १६.

ऋज्रऽअश्वस्य १. १००, १६.

ऋज्रऽअश्वे १. ११७, १७.

ऋज्रः ९. ९७, ९; १०. २०, ९.

ऋज्रं ८. २५, २२.

ऋज्रा १. १७४, ५; ४. १६, ११; ८. १, ३२; १०. २२, ५.

ऋज्राः ८. ३४, १७.

ऋज्रासः ७. १८, २३.

ऋज्रे इति ६. ६३, ९.

ऋज्रेभिः १. ११७, १४.

ऋज्रेषु ८. ६८, १८.

ऋज्रौ ८. ६८, १५.

ऋंजत ५. ८७, ५.

ऋंजती १. १७२, ५.

ऋंजते १. ६, ९; ३७, ३; १२२, १३; १४१, ६; १४३, ५; ७; २. १, ८; २, ५; ५. ४८, ५.

ऋंजन् १. ९५, ७; ३. ३१, १; ४. ३८, ७; ८.

ऋंजंति ३. ४३, ६.

ऋंजसानः १. ५८, ३; ४. २१, ५.

ऋंजसानं १. ९६, ३.

ऋंजसे ८. ४, १७.

ऋंजसे ४. ८, १; ५. १३, ६; ६. १५, १; ४; १०. ७६, १; १४२, २.

ऋंजे ३. ४, ७; ४. २६, १.

ऋणः ६. १२, ५.

ऋणऽकातिं ८. ६१, १२.

ऋणऽचित् २. २३, १७.

ऋणऽच्युतं ६. ६१, १.

ऋणधत् १. ८४, १६.

ऋणंति ५. ५६, ४.

ऋणं २. २४, १३; ४. ३, १३; ८. ३२, १६; ४७, १७.

ऋणऽचयस्य ५. ३०, १२.

ऋणंऽचये ५. ३०, १४.

ऋणऽयाः २. २३, ११; १७; ४. २३, ७; ९. ११०, १; १०. ८९, ८.

ऋणऽयावा १. ८७, ४.

ऋणवः १. ४८, १५; १३८, २.

ऋणवः ७. ८, ३.

ऋणऽवा १०. ३४, १०.

ऋणऽवानं १. १६९, ७.

ऋणा २. २८, ९; ४. २३, ७; ९. ४७, २.

ऋणाऽइव १०. १२७, ७.

ऋणानि २. २७, ४.

ऋणुत ५. ४५, ६.

ऋणोः १. ३०, १४; १५; १७४, २; ९; ६. १८, ५; ९. १०२, ८.

ऋणोति १. ३५, ९.

ऋणोमि ८. २४, ६.

ऋण्वति १. ५८, ३; १२८, ६[२]; १४४, ५; ३. २, १; ११, २; ५. १६, २; ६. २, ६.

ऋण्वथः १. १३९, ४; १५१, ५.

ऋण्वन् ७. २, १.

ऋण्वन् १. ६९, ५; ७. १, २; ५, ६.

ऋण्वंति ९. ७, ५.

ऋण्वंति ९. १०, ६.

ऋण्विरे १०. २५, ५.
ऋण्वे ५. ७४, ५.
ऋतः ८. ६०, ५; ९. ६२, ३०.
ऋतःऽपते ८. २६, २१.
ऋतऽचित् १. १४५, ५; ४. १६, १०; ५. ३, ९; ७. ८५, ४.
ऋतऽचित् ४. ३, ४.
ऋतऽजाः ३. ५८, ८; ४. ४०, ५.
ऋतंऽजात १. १४४, ७.
ऋतऽजात १. १८९, ६; ३. २०, २; ६. १३, ३.
ऋतऽजातः १. ३६, १९; ९. १०८, ८.
ऋतऽजातया १०. १३८, २.
ऋतजातऽसत्याः ४. ५१, ७.
ऋतऽजातस्य ३. ६, १०.
ऋतऽजाताः ३. ५४, १३; ५. ६१, १४; ७. ६६, १३.
ऋतऽजुरे १०. १४३, १.
ऋतंऽज्ञाः ५. ५७, ८.
ऋतऽज्ञाः १. ७२, ८; ४. १९, ७; ७. ३५, १५; १०. १५, १; ६४, १६; ६५, ३; १०४, ४.
ऋतऽज्ञाः ७. ३८, ८.
ऋतऽज्ञां ५. ४३, ६.
ऋतऽज्येन २. २४, ८.
ऋतऽद्युम्न ९. ११३, ४.
ऋतंऽधीतयः ५. ५१, २.
ऋतऽधीतयः ४. ५५, २; ६. ५१, १०.
ऋतऽधीतिऽभिः ६. ३९, २.
ऋतऽधीतिं १०. ४७, ६.
ऋतनिऽध्यः २. २७, १२.
ऋतऽपाः १. ११३, १२; ६. ३, १; ७. २०, ६.
ऋतऽपेशसे ५. ६६, १.
ऋतऽप्रजात २. २३, १५.
ऋतऽप्रजातः १. ६५, ५.
ऋतऽप्रजातां १०. ६७, १.
ऋतऽप्रवीतं १. ७०, ४.
ऋतप्सु इत्यृतऽप्सु १. १८०, ३.
ऋतं १. ४१, ४; ६८, २; ७१, ३; ७५, ५; १०५, ४; ५; १२; १५; १५१, ४; १५२, ३; १८५, १०; १८८, २; २. २८, ४; ३०, १; ३. ४, ७[2]; ५४, ३; ५५, ३; ५६, २; ४. १, १३; २, १४; १६; १९; ३, ९; ५, ११; २३, ९; १०[2]; ४०, ५; ५६, ६; ७; ५. १२, २[2]; ६; १५, २; ४५, ७; ५९, १; ६२, १; ६६, ५; ६८, १; ४; ७. २१, ५; २३, ४; ३९, १; १०१, ६; ८. २५, ४; २७, १९; २०; ८६, ५; ९७, १५; ९. ५६, १; ६६, २४; ६९, ३; ७०, ६; ७४, ३; ९७, २३; २४; १०७, १५[2]; १०८, ८; ११३, ४; १०. १३, ५; ३१, ११; ३४, १२; ३७, १; ६१, १०; ११; ६६, ४; ६७, २; ७८, २; ७९, ४; ८७, ११; १३८, १; १७९, ३; १९०, १.
ऋतऽयतः २. १, २; ३२, १.
ऋतऽयते १. ९०, ६; ९१, ७; ४. ८, ३; ५. २७, ४; ८. ७३, १.
ऋतयन् ५. १२, ३; ४३, ७.
ऋतऽयन् १. ११७, २२; ५. ४१, १; ७. ८७, १.
ऋतऽयंत ८. ३, १४.
ऋतऽयंतीः ९. ९४, २.
ऋतऽयवः ५. ८, १; ५४, १२; १०. ११५, ७.
ऋतऽयवः ८. २३, ९.
ऋतऽया २. ११, १२.
ऋतयिनी इत्यृतऽयिनी १०. ५, ३.
ऋतऽयुः ८. ७०, १०.
ऋतऽयुक् ६. ३९, २.
ऋतऽयुक्तिं १०. ६१, १०.
ऋतयुक्ऽभिः ४. ५१, ५; ६. ३९, ४; ७. ७१, ३.
ऋतयुऽभिः ९. ३, ३; ३६, ४; ६४, ५.
ऋतऽयुं ८. ७९, ६.
ऋतऽयोः १. १६९, ५; ७. ३४, १७.
ऋतंऽवः २. २८, ६; ३. १४, २.
ऋतवः १०. १८, ५.
ऋतऽवः ४. १०, ७; ७. १, १९.
ऋतऽवनि ८. २३, ८.
ऋतऽवरि २. ४१, १८.
ऋतऽवरी ३. ६१, ६; ४. ५२, २; ६. ६१, ९; ८. २५, ३; ७३, १६.
ऋतंवरी इत्यृतंऽवरी ३. ५४, ४.
ऋतवरी इत्यृतऽवरी १. १६०, १; ३. ६, १०; ४. ५६, २; १०. ३६, २; ६६, ६.
ऋतंऽवरीः ३. ३३, ५.
ऋतऽवरीः ३. ५६, ५.
ऋतवरीःऽइव ४. १८, ६.
ऋतऽवरीं ५. ८०, १.
ऋतवसो इत्यृतऽवसो ८. १०१, ५.
ऋतऽवा १. ७७, १; २; ५; १२२, ९; २. ३५, ८; ३. १३, २; २०, ४; ५३, ८; ५४, १२; ४. २, १; ६, ५; ७, ७; ३८, ७; ४२, ४; ५. १, ६; २५, १; ६. १२, १; १५, १३; ६८, ५; ७३, १; ७. ३, १; ७, ४; ६१, २; ८. ७५, ३; ९. ९६, १३; ९७, ४८; ११०, ११; १०. २, २; ६, २; ७, ४; १६८, ३.
ऋतऽवाकेन ९. ११३, २.
ऋतऽवानः २. २४, ७; २७, ४; ३. ५६, ८; ५. ६७, ४; ७. ३९, ७; ६२, ३; ६६, १३; ७६, ४; ८७, ३; १०. १५४, ४.
ऋतऽवानं ३. २, १३; ४. १, २; ७, ३; ८. २३, ९; १०. १४०, ६.
ऋतंऽवाना १. १३६, ४; १५१, ८.
ऋतऽवाना ५. ६५, २; ८. २३, ३०; २५, १; ७; ८.
ऋतऽवानौ १. १५१, ४.
ऋतऽवानौ ८. २५, ४.
ऋतऽवृधः १. १३, ६; १४, ७; ४४, १४; १४२, ६; ५. ४४, ४; ६. १५, १८; ५०, १४; ५२, १०; ७. ६६, १०; १३; ८२, १०; ८. ८९, १; ९. ४२, ५; १०२, ६; १०. १६, ११; ६५, ७; ६६, १; १५४, ४.
ऋतऽवृधः ६. ७५, १०.
ऋतऽवृधा १. १०६, ३; १५९, १; ५. ६५, २; ९. ९, ३.
ऋतऽवृधा १. ४७, १; ३; ५; २. ४१, ४; ३. ६२, १८; ६. ५९, ४.

ऋतऽवृधां १०. ६५, ३.

ऋतऽवृधै ३. २, १.

ऋतऽवृधौ १. २३, ५.

ऋतऽवृधो १. २, ८.

ऋतऽन्नै ८. १०३, ८.

ऋतऽसत् ४. ४०, ५.

ऋतऽसापः १. १७९, २; ५. ४१, ६; ६. २१, ११; ५०, २; ७. ५६, १२; १०. ६६, ८; १५४, ४.

ऋतऽस्तुभं १. ११२, २०.

ऋतऽस्पृशः ४. ५०, ३; ५. ६७, ४.

ऋतऽस्पृशं ८. ७६, १२.

ऋतऽस्पृशा १. २, ८.

ऋर्तस्य ५. ६३, १.

ऋतस्यं १. १, ८; २३, ५; ४३, ९; ४६, ११; ६५, २^{२}; ६७, ४; ६८, ३^{२}; ७३, ६; ७९, ३^{२}; ८४, ४; १६; १०५, ६; १२३, ९; १३, १२४, ३; १२८, २; १३२, ३; १३६, २; १४१, १; १४२, ७; १४३, ७; १४४, २; १४७, १; १५६, ३; ५; १६३, ५; १६४, ११; ३७; ४७; २. २३, ३; १७; २८, ५; ३४, १३; ३. १, ११; २, ८; ५, २; ६, ६; ७, २; १०, २; १२, ७; २७, ११; ३१, १; ५; ५४, ६; ५५, १२–१४; ६१, ७; ६२, १३; १८; ४. १, १२; २, ३; ३, ४; ५, ९; ७, ७; १०, २; २१, ३; २३, ८^{३}; ९; १०; ४२, ४; ४४, ३; ५१, ८; ५७, २; ५. ५, ६; ७, ३; १२, १; २; २१, ४; ४१, १; ४५, ८; ६. १३, २; १६, ३५; १७, ७; ४४, ८; ४८, ५; ४९, १५; ५१, १; ३; ९^{२}; ५५, १; ७. ७, ६; ३६, १; ५; ३८, २; ४०, ४; ४३, ४; ४४, ५; ५३, २; ६०, ५; ६५, ३; ६६, १२; ९५, ६; ८. ६, २^{२}; ८; १०; १९; ७, २१; ८, २३; १२, ३; १३–१५; १९, ३५; २२, ७; ३१, १३; ५२, ९; ५९, ४; ८३, ३; ८६, ५; ९५, ५; १००, ४; ५; ९. ७, १; ८, ३; १२, १; १३, ९; ३२, ४; ३३, २; ५; ३४, ५; ३९, ६; ४८, ४; ६३, ४; १४; २१; ६४, ११; १७; २०; २२; ६६, १२; ६८, ५; ७२, ६; ७३, १; ६; ८; ९; ७४, ४; ७५, २; ७६, ४; ७७, १; ८६, २५; ३२; ३३; ८९, २; ९५, २; ९७, ३२; ३४; १०२, १; ७; ८; १०७, ४; ११०, ४; १११, २; १०. ५, २; ४; ७; ८, ३; ५; १३, ३; ३०, ११; ३१, २; ३५, ८; ४३, ९; ५९, ८; ६१, १४; १९; ६५, ७; ८; ६६, १३; ६८, ४; ७०, २; ८०, ६; ८५, २४; ८६, १०; ९२, ४; १००, १०; ११०, २; ११; १११, २; ११८, ७; १२३, २; १२४, ३; १३३, ६; १७७, २.

ऋतस्य ७. ६४, २.

ऋता १. ४६, १४; ६७, ४; १६१, ९; ६. १५, १४; ६७, ४; ९. ९७, ३७; १०. १०, ४; १०६, ५.

ऋतात् १. ३६, ११; १३९, २; ८. १३, २६; १०. ७३, ५.

ऋतानां १. १६५, १३; ४. २३, ४.

ऋतानि १. १७९, २; १०. १२२, ६.

ऋताय १. ३४, १०; १२१, ४; १३७, २; १५१, ३; ६; १५३, ३; ४. ३, ८; २३, १०^{२}; ५. २०, ४; ९. १७, ८; ९७, २३; १०. ८, ४; ५.

ऋतिऽसहः ८. ४५, ३५.

ऋतिऽसहं १. ६४, १५; ६. १४, ४; ८. ६८, १; ८८, १.

ऋतुः १. १६२, १९; २. १३, १; ५. ४६, ८.

ऋतुऽथा १. १६२, १९; १६४, ४४; १७०, ५; २. ३, ७; ४३, १; ५. ३२, १२; ६. ९, ३; १८, ३; ६२, ९; ८. १३, १९; ४४, ८; ९. ९७, १२; १०. २८, ५; ४०, ४; ८५, १६; ९८, ४; ११०, १०; १३१, ३.

ऋतुनां १. १५, १–४; ६; ११; १२; २. ३७, ६.

ऋतुऽपते १०. २, १.

ऋतुऽपाः ३. २०, ४; ५. १२, ३; १०. ९९, १०.

ऋतुऽपाः ३. ४७, ३.

ऋतुऽपाभिः ४. ३४, ७.

ऋतुऽभिः १. १५, ९; १०; ८४, १८; २. ३७, १–३; ३. ४७, ३; ४. ३४, २; ५३, ७; ५. ३२, २; ६. ५२, १०; ९. ६६, ३; १०. २, ४; ७, ६; १८, ५.

ऋतुं ७. १०३, ९.

ऋतुऽशः १. १६२, ४; १०. २, ५; ५५, ३; ९८, ११.

ऋतून् १. १५, ५; ४९, ३; ९५, ३; २. ३८, ४; १०. २, १; ३; ११, १; ८५, १८.

ऋतूनां ५. १२, ३.

ऋते १. १८, ७; १४१, ११; १६४, ८; १९०, २; २. १२, ९; १६, २; २९, ४; ४. ३३, ११; ५. ४४, २; ६. ७, १; ६७, ८; ७. ११, १; १६, ६; ८. १, १२; २, ३९; २७, १७; ९. ६९, ६; १०. ८६, १२; ९९, २; ११२, ९.

ऋतेऽकर्म १०. ५५, ७.

ऋतेऽजाः १. ११३, १२; ६. ३, १; ७. २०, ६.

ऋतेन १. २, ८; २३, ५; १३३, १; १५२, १; १८५, ६; २. २७, ८; ३. ४, ५; ५, ३; ३१, ९; २१; ५८, २; ४. ३, ९–१२; २३, ९^{२}; ४२, ४; ५. १, ७; १२, ३; १५, २; ६२, १; ६३, ७; ६८, ४; ८०, १; ६. ३९, ४; ६८, २; ७. ३४, ८; ५६, १२; ७५, १; ८. ८६, ५; ९. ८०, १; १०. १२, १; २; ६२, ३; ८५, १; १०८, ८; ११; १०९, १; १२३, ४; १२४, ५; १३९, ४.

ऋतैः ९. ७०, १.

ऋतोः २. २८, ५.

ऋत्विक् २. ५, ७.

ऋत्विजः १. ६०, ३; ८. ५८, १; ९. ११४, ३; १०. २, १.

ऋत्विजं १. १, १; ४४, ११; ४५, ७; २. ५, ७; ३. १०, २; ५. २२,

२; ७. १६, ६; ८. ४४, ६; १०. ७, ५.
ऋत्विजां ८. ३८, १.
ऋत्विजा १०. ७०, ७.
ऋत्विजां १०. ११४, ९.
ऋत्वियः १. १३५, ३; १४३, १; ३. २९, १०; ४१, २; ५. ७५, ९; ८. १९, ३१; ९. ७२, ४.
ऋत्वियं २. १, २; ८. ४०, ११; १०. ९१, ४; ६; १००, २; १७९, १.
ऋत्वियऽवतः ८. ८, १३.
ऋत्वियऽवती ८. १२, १०; ८०, ७.
ऋत्वियाः १. १९०, २.
ऋत्वियाय ८. ६३, ११.
ऋत्व्ये १०. १८३, २.
ऋदंतु ७. १०४, २४.
ऋदुऽपे ८. ७७, ११.
ऋदुऽवृधा ८. ७७, ११.
ऋदूदरः २. ३३, ५.
ऋदूदराः ३. ५४, १०.
ऋदूदरेण ८. ४८, १०.
ऋधक् ३. २५, १; ४. १८, ४; ३४, ९; ६. ४०, ५; ४९, १०; ७. ५७, ४; ६१, ३; ८. १८, ११; १०१, १; १०. ४९, ७; ७९, २; ९३, ८; १०५, ८.
ऋधक् ९. ६४, ३०.
ऋधंत् ६. २, ४.
ऋधत्ऽरयः ८. ४६, २३.
ऋधत्ऽवाराय ६. ३, २.
ऋधंतः ७. ८७, ७.
ऋधाथे इति १. १७, ९.
ऋधीमहि ६. ३७, १.
ऋध्नोति १. १८, ८.
ऋध्यतां १०. ८५, २७.
ऋध्याः ३. ५०, १; ८. ४८, २.
ऋध्यां ५. ६०, १.
ऋध्याम १. ३१, ८; २. २८, ५; ४. १०, १; १०. १०६, ११.
ऋंधन् १. १७३, ११; ३. ३१, २; १०. ११०, २.
ऋबीसं ५. ७८, ४; १०. ३९, ९.
ऋबीसात् १. ११७, ३.
ऋबीसे १. ११६, ८.
ऋभवः १. २०, ४; ५१, २; ११०, ४–६; १११, १; ३. ६०, ३; ४. ३३, २; ४²; ६–८; ३४, ९; ३६, ६; ५. ४६, ४; ५१, १३; ७. ३५, १२; ५१, ३; ८. ३, ७; ७५, ५; १०. ३९, १२; ६६, १०; ८०, ७.
ऋभवः १. ११०, १; ८; १११, ३; १६१, ४; ११; १३; ३. ५४, १२; ६०, २; ४; ४. ३३, ५; १०; ११; ३४, २–४; ८; १०; ११; ३५, १; ३; ४–६; ९; ३६, १–४; ७–९; ३७, ६; १०. ६५, १०.
ऋभुः १. ११०, ७²; १११, ५; १२१, २; १६१, ६; २. १, १०; ३. ५, ६; ३६, २; ४. ३३, ३; ३४, १; ५. ७, ७; ६. ३, ८; ७. ४८, २; ९. २१, ६; ८७, ३; १०. २३, २; ९३, ७; ८²; १०५, ६; १४४, २².
ऋभुक्षणः ७. ४८, १.
ऋभुक्षणः १०. ९२, ११.
ऋभुक्षणः ४. ३७, ३; ५; ७; ८; ७. ३७, १; २; ८. ७, ९; १२; २०, २; १०. ९३, ७.
ऋभुक्षणं १. १११, ४; ८. ४५, २९; ९३, ३४; १०. ७४, ५.
ऋभुक्षाः १. ६३, ३; १६२, १; १६७, १०; १८६, १०; २. ३१, ६; ४. ३३, ९; ५. ४२, ५; ६. ५०, १२; ७. ३७, ४; ४८, ३; ८. ९६, २१; १०. २३, २; ६४, १०; ९३, ८.
ऋभुक्षाः ४. ३४, ५; ३७, १.
ऋभुतः ४. ३६, ५.
ऋभुऽभिः ३. ५४, १७; ६०, ५; ७; ४. ३५, ७; ७. ४८, २; ८. ९, १२.
ऋभुऽभ्यः ४. ३३, १.
ऋभुं ४. ३७, ५; ८. ९३, ३४.
ऋभुऽमत् १. १११, २.
ऋभुऽमंतं ३. ५२, ६.
ऋभुऽमंतां ८. ३५, १५.
ऋभुऽमान् १. ११०, ९; ३. ६०, ६.
ऋभुऽस्थिर ८. ७७, ८.
ऋभू इति १०. १०६, ७.
ऋभूणां ४. ३५, २; ५१, ६; १०. १७६, १.
ऋभून् १. १११, ४.
ऋभ्वं ६. ४९, ९; १०. १२०, ६.
ऋभ्वसः ९. ८६, ५.
ऋभ्वसं १. ५६, १; ५. ५२, ८; ८. ७०, ३.
ऋभ्वा १. १००, ५; १२; १२१, ९; ६. ३४, २; १०. २०, ५; ६९, ७; ९९, ५.
ऋश्यः ८. ४, १०.
ऋश्यऽदात् १०. ३९, ८.
ऋषभं १०. १६६, १.
ऋषभस्य ६. २८, ८.
ऋषभासः ६. १६, ४७; १०. ९१, १४.
ऋषयः १. ४८, १४; १६२, ७; १६४, १५; ४. ४२, ८; ५०, १; ७. २२, ९; ८. ६, १२; ८, ६; ९. ८६, ४; ९२, २; १०. ५४, ३; ६२, ५; ७३, ११; ८०, ५; ८२, ४; ९०, ७; ९८, ९; १०८, ८; ११; ११५, ९; १३०, ५–७; १५०, ४.
ऋषयः ३. ५३, १०; १०. ६२, ४.
ऋषये ५. ७८, ६; १०. २७, २२; ७३, ७.
ऋषिः १. ३१, १; ६६, २; १०६, ६; १७९, ६; ३. २१, ३; ५३, ९; ४. २६, १; ३६, ६; ५. २९, १; ७५, १; ६. १४, २; १६, १४; ८. ३, १४; ४, २०; ६, ४१; ८, ८; १५; ९, ७; १०; १६, ७; २३, १६; ५१, २; ७९, १; ९. ३५, ४; ६६, २०; ८७, ३; ९६, ६; १०७, ७; १०. २६, ५; ३३, ४; ८१, १; ९८, ५.
ऋषिऽकृत् १. ३१, १६; ९. ९६, १८.
ऋषिऽचोदनः ८. ५१, ३.
ऋषिऽद्विषे १. ३९, १०.
ऋषिऽबंधवे ८. १००, ६.
ऋषिऽभिः १. १, २; २३, २४; १८९,

८; **४.** २०, ५; **८.** ३, ४; ७०, १४; **९.** ६७, ३१; ३२; ६८, ७; **१०.** ४५, १२.
ऋषिऽभ्यः **१०.** १७, १५.
ऋषिऽभ्यः **८.** ५९, ६.
ऋषिं **१.** १०, ११; ११७, ३; ४; **३.** ४३, ५; **५.** ५४, ७; १४; **७.** ३३, १३; ८८, ४; **९.** ५४, १; **१०.** १३, ४; ८०, ४; १०७, ६; १२५, ५.
ऋषिऽमनाः **९.** ९६, १८.
ऋषिंऽवः **८.** २, २८.
ऋषिऽवत् **१०.** ६६, १४.
ऋषिषाट् **९.** ७६, ४.
ऋषिंषु **१०.** ७१, ३.
ऋषिऽसान् **९.** ८६, ४.
ऋषिंऽस्तुता **७.** ७५, ५.
ऋषिंऽस्तुताभिः **८.** १३, २५.
ऋषिऽस्वरं **५.** ४४, ८.
ऋषीणां **१.** ८४, २; **५.** ६५, ६; ६६, ५; **६.** ३४, १; ४४, १३; **७.** २८, २; २९, ४; ७०, ४; ५; **९.** ६२, १७; १०३, ३; **१०.** २२, १; ८९, १६; १४८, ३.
ऋषींन् **१०.** १५४, ५.
ऋषूणां **१.** १२७, १०^{२}; **५.** २५, १; **८.** ७१, १५; **१०.** ६, १.
ऋषे **५.** ५९, ८; **८.** २३, २४; **९.** ११४, २; **१०.** ३०, १०.
ऋषे **५.** ५२, १३; १४; **८.** २६, १०.
ऋषेः **५.** ३३, १०; **१०.** २३, ७.
ऋष्यः **१.** ६४, ४; **५.** ५४, ११; ५७, ६; **७.** ५५, २; **८.** २०, ११; २८, ५.
ऋष्टिः **१.** १६७, ३; १६९, ३.
ऋष्टिऽभिः **१.** ३७, २; ६४, ८; ८५, ४; **२.** ३६, २; **१०.** ८७, ७; २३.
ऋष्टिमत्ऽभिः **१.** ८८, १.
ऋष्टिऽमंतः **३.** ५४, १३; **५.** ५७, २; ६०, ३.
ऋष्टिऽविद्युतः **५.** ५२, १३.
ऋष्टिऽविद्युतः **१.** १६८, ५.
ऋष्टिषु **१.** १६६, ४.

ऋष्टी **५.** ५२, ६.
ऋष्व **३.** ३५, ८; **४.** २, २; **५.** ३३, ३; **१०.** १२, ६.
ऋष्वः **१.** ८१, ४; १४६, २; **२.** २१, ४; **३.** ५, ५; ७; १०; **४.** २०, ६; ९; २३, १; **६.** १७, ७; २९, ६; **७.** ९७, ७; **८.** ४६, १२; ५०, ७; ९३, ९; **१०.** १४८, २.
ऋष्वऽओजाः **१०.** १०५, ६.
ऋष्वं **३.** ३२, ७; **४.** १९, १; **६.** १९, २; २०, ९; २६, ४; ४९, १०; **७.** ७७, ६; ८६, १; ९९, २; **९.** ८९, ४; **१०.** ३६, ७.
ऋष्वया **६.** १८, १०.
ऋष्वऽवीरस्य **१.** ५२, १३.
ऋष्वस्य **१.** २५, ९.
ऋष्वा **६.** ४७, ८; **१०.** ७३, ३.
ऋष्वाः **५.** ५२, ६; १३; **६.** २४, ८.
ऋष्वात् **४.** २२, ४; **७.** ६१, ३.
ऋष्वान् **६.** ६३, ९.
ऋष्वासः **१.** ६४, २.
ऋष्वे **६.** ६४, ४.
ऋष्वे इति **७.** ६२, ४.
ऋष्वेभिः **१.** २८, ८; **८.** ३, १७; ५०, ७; **१०.** १०५, ६.
ऋष्वैः **१०.** ७३, ६.
ऋष्वौ **१.** २८, ८.
ऋहते **१०.** २८, ९.

ए

एकंऽआयुः **१.** ३१, ५.
एकंऽईषं **१०.** १३५, ३.
एकः **१.** ७, ९; ३२, १२; ३३, ४; ५२, १४; ६१, १५; ६८, १; ७१, ९; ८४, ७; १००, ७; १४३, ४; १४५, ३; १५४, ३; ४; १६१, ९^{२}; १०^{२}; १६२, १९; १६४, २; १०; ४४^{२}; १६५, ३; १७६, २; **२.** १३, ३^{२}; ६; २९, ५; **३.** १, १०; ३, ११; ३०, ४; ५; ११; ३१, ४; ४६, २; ५१, ४; ५५, ६; ५६, २; **४.** १७, ५; ९; १९; ३०, ५; ३२, ७; **५.** ३०, ४; ३२, ३; ९; ६२, २; ८१, १; ५; **६.** १८, २; ३; २२, १; ३०, १; ३१, १; ३४, २; ३६, ४; ४५, २०; ५९, ५; **७.** १९, १; २३, ५; २६, ३; ४; ९८, ६; १०३, ६^{४}; १०४, ३; **८.** १, २७; २, ४; ३१; ६, ४१; १३, ९; १४, १; १५, ३; ११; १६, ८; १७, १५; २४, १९; २५, १६; २९, १–३; ६; ७; ३६, ७; ३७, ४; ३९, १०; ५८, २^{२}; ६२, २; ७७, ७; ९०, ५; **१०.** ५, १; ३२, ५; ४८, ७; ५१, १; ८१, ३; ८२, ३; ८४, ४; ९१, ३; १०४, ९; ११४, ४; १२१, १; ३; ७; ८; १३८, ६; १५४, १.
एकःऽएकः **३.** २९, १५; **५.** ६१, १.
एककं **१०.** ५९, ९.
एकंऽचक्रं **१.** १६४, २.
एकऽज **१०.** ८४, ३.
एकऽजं **१.** १६४, १५.
एकऽद्यूः **८.** ८०, १०.
एकधेनुऽभिः **७.** ३८, ५.
एकंऽपदी **१.** १६४, ४१.
एकऽपरस्यं **१०.** ३४, २.
एकंऽपात् **२.** ३१, ६; **६.** ५०, १४; **७.** ३५, १३; **१०.** ६४, ४; ६५, १३; ६६, ११; ११७, ८.
एकं **१.** ९३, ४; ९५, ३^{२}; ९६, ५; ११०, ३; ५; ११७, १८; १३१, २; १६१, २; १६४, ६; ४६; ४८; **३.** १, ६; ५४, ८; ५५, १; **४.** ७, ९; १९, १; ३५, २; ३६, ४; ५८, ४^{३}; **५.** ३२, ११; ६२, १; ८५, ६; **६.** ९, ५; १७, ८; **७.** १८, ११; १७; ३३, १०; **८.** २०, १३; ५८, २; १००, ५; १०१, ६; **९.** ९, ४; २१, ३; ९७, ५५; **१०.** १४, १६; २७, १६; ४८, ७; ५५, ४; ५६, १^{२}; ८०, २; ८२, २; ६; ८५, १५; १६; १०९, ५; ११४, ५; १२९, २; ३; १३८, ६; १४२, ५.
एकंऽएकं **१.** २०, ७; **८.** ७०, १४.
एकंऽएका **५.** ५२, १७.

एकया ८. २९, ८; ६०, ९; ७७, ४; १०. ६७, ४.
एकऽशाट् ८. ३७, ३.
एकऽरूपाः १०. १६९, २.
एकऽवीरः १०. १०३, १.
एकऽशतं १०. १३०, १.
एकस्मिन् ७. ६७, ८; ८. ४५, ३४.
एकस्य १. १६४, ४४; १६५, १०; २. १३, ३; ९; ६. ४५, ५; ९. १०, ७; १०. १०, ३.
एकस्याः १. ११६, २१.
एका १. ३५, ६; ३. ७, २; ५६, २; ७. ९५, २; ८. ५८, २.
एकाऽएका १. १२३, ८.
एकादश १. १३९, ११[३].
एकादशं १०. ८५, ४५.
एकादशान् ८. ३९, ९.
एकादशासः ८. ५७, २; ९. ९२, ४.
एकादशैः १. ३४, ११; ८. ३५, ३.
एकौ ३. २, ९; ८. ७२, ७; १०. ५, ६.
एकाऽइव ३. ७, ४.
एके ८. २९, १०; १०. ११४, १०.
एकेन २. १३, ११; ३. १२, ६.
एकेभ्यः १०. १५४, १.
एजत् १. १६४, ३०; ३. ५४, ८; ४. १७, १०; १९, ६; १०. ८८, १५.
एजति ५. ७८, ८; ८. ६, २९; १०. ३७, २.
एजति १. १०, २; ५. ५९, २.
एजतु ५. ७८, ७.
एजथ ८. २०, ४.
एजात् १०. २७, ५.
एजान् ६. २५, ७.
एतऽग्वा ७. ७०, २; ८. ७०, ७.
एतऽग्वाः १. ११५, ३.
एतत् १. ८८, ५; १००, १७; १५२, २; १६२, २१; १६४, ४; ५१; २. १४, १०; ३. ३३, ८; ३६, ९; ५९, ५; ४. १८, २; ३०, ८; ११; ३५, ९; ५८, २; ६. २७, ४; ३४, ४; ५; ७. १००, ६; १०१, १; ८. ५४, १; ९३, १३; १०. १०, २; ३; ११; १२; २८, ५; १०; ११; ३२, ७; ८५, ३४[३]; ९५, १८; १०७, ८; १०८, ८; १३२, ५; १६१, १; १६५, ४[२].
एतं १. १२२, १२; १८२, ५; २. १४, २; ३; ३७, १; ४१, १४; ३. ३५, ९; ५. २, २; ११; ५८, ३; ६१, १७; ६. ४१, ३; ४; ७. ५६, १४; ६४, ४; ८७, ५; ९. १५, ७; ८; ३८, २; ३; ४६, ६; ६१, ७; १०८, ११; १०. १४, ९; १८, ४; ८; ३४, ४; ३९, १४; ४८, ४; ५१, ४; ६; ९३, ११; १२; १०८, ८.
एतंयः १०. ९१, ४.
एतया ८. २६, १९.
एतरि ५. ४१, १०; ६. १२, ४.
एतवे १. ४६, ११; ११२, ८; ५. ४४, ११; ८. ६९, १७; १०. ३९, ८.
एतवै ४. ५८, ९; १०. १०८, ६.
एतशः १. १२१, १३; १६८, ५; २. १९, ५; ५. ३१, ११; ८१, ३; ७. ६६, १४; ९. १६, १; ६४, १९; १०८, २; १०. ५३, ९.
एतशः ७. ६३, २.
एतशं १. ५४, ६; ६१, १५; ४. १७, १४; ३०, ६; ८. १, ११; ६, ३८; ५०, ९; ९. ६३, ८.
एतशस्य ६. १५, ५.
एतशा ८. ७०, ७.
एतशे ५. २९, ५.
एतशेभिः ७. ६२, २; १०. ३७, ३; ४९, ७.
एतस्यौ १०. १०९, ४.
एता १. ६९, ४; ७०, ३; ७३, १०; २. ३१, ७; ३. १, २०; ४३, ४; ४. ३, १६; ५. २९, १४; ७. ३, १०; ३६, ४; ८. ४५, ३९; ७७, ९; १०. ५०, ५; ६; ७२, २; ९५, २; १५; १३८, ६.
एताः १. १६६, १०; १६९, ६; ५. ५४, ५; १०. ७७, २.
एताः १. २५, १८; ९२, १; १६५, ८; २. ११, ३; ४. १८, ६[२]; ५८, ५; ७. ९३, ८; १०. १९, ३; १११, ९[२]; १६९, ४.
एतादृक् ८. १०२, १९; १०. २७, २४.
एतान् १. १६५, ५.
एतान् १. ३३, ७; ५३, ९; ६३, ३; १६९, १; ४. २, १२; १८, ७; ५. ५३, २; १०. ४८, ६.
एतानां १. १६९, ७.
एतानि १. ९३, ५; ११७, १०; २५; २. ३९, ८; ६. ७४, ३; ७. ५६, ४; ८. २, ३४; ९. ७८, ५; १०. ३२, ९; ७३, ८; ९८, १०; ११.
एतां १. १६४, २६; ३. २९, १; ४. ३३, ६; ५. ३, ७; ७. १००, ३; ४; १०. १३, ३; १५, १४; १६, २; १८, १०; १३; ८८, ६.
एतावत् ५. ७९, १०; ७. ३२, १८; ५७, ३; ८. ५, २७; १०. ३१, ८.
एतावतः ८. ७, १५; ४९, ९; ५०, ९.
एतावता १०. १३२, ४.
एतावती १०. १२५, ८.
एतावतं ७. १००, १.
एतावान् १०. ९०, ३.
एति १. ७१, ९; १०३, ६; १४०, ५; १४४, १; १६४, ५१; ४. २२, १; ५०, ८; ५. २८, १; ८२, ८; ६. ३, ३; ४८, २१; ५१, १; ७. १, ६; १६; २३; ८. ४, ३; ९. ९८, ३; १०. ३०, ६; ६३, १६; ७५, ३.
एति १. २३, ११; २४, १०; ९५, ९; १०१, ७; १०७, १; ११३, ८; १०; १६; ११५, २; १२३, ७[२]; १२४, ३; ७–९; १२८, ३; १४०, ६; ८; १५२, ३; १५५, ६; १५७, १; १६२, २; ४; १८; १६४, १४; ३८; १९१, ८; २. ४, ७; ३६, ६; ४०, ५; ३. २, १२; ६, १; २७, ७; ३३, २; ५४, ५; ६२, १३; ४. ७, ४; ५; ११, ३; १३, १; १७, १२; ५. ३७, ३; ४४, १२;

१३; ४७, १; ५६, ३; ५८, ४; **६.** ४, ५; ४७, १७; ६३, ४; ७५, १४; **७.** ३, ३; ४; ६; ४, ८; ३७, ७; ३९, १; ६०, २; ६१, १; ६३, १; ३–५; ६६, १४; ८०, २; १०३, २; ३; १०४, २१; **८.** १२, १०; २३, २२; ७२, ९; ८०, ७; **९.** ३३, ४; ३९, ३; ४४, ३; ६१, ८; ७०, ६; ७१, २^{२}; ६; ७२, ३; ८२, १; ८५, ९; ८६, ७; ३१; ९२, ३; ९६, १; ६; १७; २२; ९७, १; ७; १३; १०१, १६; **१०.** ३, १; ३; १७, १; २०, ४–६; २७, १३; ३१, ९; ३२, ७; ३४, ६; १०; ३५, ८; ३७, २; ६१, २६; ८५, ६; १९; ८८, १५; ९४, ८; १०२, ४, १०७, ५^{२}; ११७, ८^{२}; १६८, १^{२}.

एतु **१.** ४०, ३^{२}; ९१, १६; १५४, ३; १८६, १; **२.** ३, ९; ३३, १; **३.** ३०, ६; **४.** ३२, १८; **५.** १२, ६; २२, २; ४९, ५; **६.** १५, १२; १९, ९^{२}; ५४, ५; **७.** ४, ८; १८, ३; ३४, १; १३; ३५, ८; ३६, १; ९; ४०, १; ४३, २; ६६, १; ८४, ३; १०४, १०; **८.** १९, २७; २४, २९; २७, ३; ३१, ११; ४६, २१; ६७, १५; १००, ११; **१०.** १३, १; १७, ५; ३०, १; ५७, ४; ६२, ११; ८७, ११; १५; १००, ४; १०३, ८; ११०, ८; १३४, ५; १४९, ४; १५२, २.

एते **१.** ५४, ९; ८१, ९; १०५, ११; १२२, १३; १३५, ६; १६५, १; १२; १९१, ५; **२.** २८, ४; **४.** ५८, ६; **५.** १२, ५^{२}; ३०, ६; ४४, ४; ५९, ८; ६०, ५; **७.** ७, ६; १८, १५; १९, १०; २५, ५; ७५, ३; १०३, ९; १०४, २०; **८.** १, ३०; ४३, ५; **९.** ८, १; २१, १; ४; ७; २२, १–५; ४६, ३; ६२, १; २२; ६३, ४; १४; ६९, ९; ८७, ५; ८८, ६; ९७, २०; १०१, १२; **१०.** १०, ८; २८, १२; ७१, ९; ७६, ८; ९४, १–३; ९५, १; १२०, ३; १८१, ३.

एते इति **१.** १४४, ६; **३.** ५४, ८; **७.** ९९, ३.

एतेन **१.** ३१, १८; १७३, १३; **५.** ८३, ६.

एतेभिः **५.** ५२, १०.

एतेभ्यः **१०.** १७, ३.

एतो इति **५.** ४५, ५; **८.** २४, १९.

एतोः **२.** १५, ५; ३८, ३.

एतौ **१०.** २७, २०; ८५, १८.

एधः **१.** १५८, ४.

एधतु **८.** ८६, ३.

एधते **८.** ७४, ४; **१०.** ६, १; ६०, ४.

एधते **१.** ४१, २; **२.** २५, ५; **८.** ४६, ५; ८४, ९; **१०.** ६३, १३.

एधते **१०.** ८५, २८.

एधमानऽद्विट् **६.** ४७, १६.

एधस्व **१०.** ८६, १८.

एधि **१.** ९१, १५; **४.** १, ५; **५.** ९, ७; **६.** १७, १४; **७.** ५४, २; ५५, १; **१०.** ५६, १; ८४, २; ६; ८५, ४४; १०३, ४; १७३, १; २.

एन **१.** १७३, ९; **५.** २, ११; **९.** ९६, २; **१०.** १०८, ३.

एनः **१.** २४, ९; १२५, ७; १८९, १; **२.** १२, १०; २८, ७; **३.** ७, १०; **५.** ३, ७; **६.** ५१, ७; ८; ७४, ३; **७.** १८, १८; ५२, २; ५८, ५; ८६, ३; **१०.** ३६, ९; ३७, १२; ७९, ६; १२८, ४; १३२, ५.

एनं **१.** ९, २; २४, १३; ३२, ३; ८०, ९; १२; ९४, २; ९६, ६; १२३, १; १६२, ३; ७; १६३, २^{२}; **२.** १२, ५; २२, १–३; **३.** २, ७; ९, ५; ३२, १३; ३६, ४; ५९, २; **४.** २, ९; १७, ५; २३, ३; २४, १०; ३८, ५; ९; ५७, ३; **५.** १२, ३; **६.** २४, १०; ३८, २; ४; ४२, २; ५६, १; **७.** १, ६; २८, ५; ३३, १४; १०३, २; **८.** १, १७; १९; २, ३७; २३, ९; ६६, ७; ८०, ४; **९.** ३४, ६; १०९, २०; **१०.** १४, ११; १६, १^{२}; ४; १८, ११; २८, २; ३२, ८; ३४, ४; ४४, ३; ४५, १; ८; ४८, ९; ७१, ५; ७३, १०; ८७, ५; ८; ११; १५; ८८, ११; ९५, १४; १०२, ५; १३०, २; १६१, १^{२}; २; ३; १६८, २.

एनसः **४.** १२, ५; **७.** २०, १; ८९, ५; **८.** १८, १२; ४७, ८; ६७, १७; **१०.** ६३, ८.

एनसा **१०.** १३२, ४.

एनस्वंतः **७.** ८८, ६.

एनस्वंतं **८.** १८, १२.

एना **१.** ३०, ३; १०५, १९; १६४, ५; १७; १८; ४३; १७१, १; **२.** ६, २; ९, ६; ३४, १४; **३.** ३३, ४; **४.** ३६, ७; **५.** १९, ३; ५३, १२; ७३, ४; **६.** २०, १०; ४४, १७; **७.** १६, १; ७१, ४; ९३, ७; **८.** ५, ३९; २१, ६; ९६, ८; **९.** ६१, ११; ९७, ५२; ५३; **१०.** १४, २; ४; २३, ७; २७, २१; ३१, ८; ८२, ५; ८५, २७; ११२, ६; १४४, ५^{२}; १४८, ३.

एनांसि **१.** २४, १४; **४.** १२, ४.

एनाः **८.** ९७, १४; **९.** ९७, २९; **१०.** १९, २^{४}; ८; ३०, १४; १०८, ५.

एनान् **१.** १६१, ५^{२}; **५.** ५२, ६; **७.** १०३, ३; **१०.** ६१, २३; ८७, १८; ९३, २; ११०, ३.

एनां **८.** ६, १९.

एनां **१.** १६४, २६; **१०.** ७१, ४.

एनी **१०.** १२, ३; ७५, ७.

एनी इति **१.** १४४, ६.

एनीः **५.** ८५, ६; **१०.** २०, २; ८७, ७.

एनीं **५.** ३३, ६; **१०.** ३, २.

एने इति **१.** १४६, २; **१०.** ८२, १.

एनोः **१.** १३६, १; ५; **६.** ६९, ८; **७.** १०३, ४.

एभ्यः **५.** ५३, ७; **८.** ६९, १०.

एभिः **१.** ५३, ४^{२}; १६६, १४; **३.**

५०, १; **४.** ३, १५; १०, ३; १६, १९; १७, ११; **६.** १६, १६; १९, १३; २५, १; **७.** १, ८; २८, ४; ६२, २; **८.** ४६, २६; **१०.** ९३, १.

एभिः **७.** ३३, ३[२]; **१०.** ३४, ५; ५५, ७.

एभ्यः **१.** ६९, ४; **६.** १९, १२.

एभ्युः **१.** १३१, ५; १३२, ४; १४६, ४; ५; **३.** ५३, १६; **४.** ५४, ५; **६.** ४६, ९; ६१, ३; ६८, ४; **१०.** ३४, ८; ६४, २; १०७, ८; ११४, १०.

एमं **१.** ५८, ४; **४.** ७, ९; **६.** ३, ४.

एमंऽभिः **५.** ५९, २.

एमिं **७.** ८९, २; **१०.** ३४, ५.

एमि **१.** १७१, १; **३.** ५४, ९; **७.** १८, २२; ८६, ३; **८.** ४८, १०; १००, १; **१०.** १३, ३; १७, १०; ६६, १३; ८६, १९; १२४, २[२]; ३.

एमुषं **८.** ७७, १०.

एरिरे **१.** १२८, ८[२]; **२.** २, ३.

एव **१.** १, ३; ८, ८–१०; ५१, ६; ६१, ९; १०; १६; ६२, १२; ७६, ५; ७७, ५; ९५, ११; ९६, ९; १०८, १३; ११३, १; १२४, ६; १४०, ७; १६१, २; १६४, १३; १६५, १२; १७३, ८; १७८, ४; १९०, ८; **२.** २, ९; १२, १; १३, ८; १९, ७; ८; २४, ४; ३०, ४; ३३, १५; **३.** ९, ३; १७, २; ३६, ३; **४.** ५, ७; १६, २०; १७, २०; १९, १; २०, ६; २१, १०; २८, ५; ३०, १; ३३, ६; ५०, ६; ८; ५१, ९; ५४, ५[२]; **५.** २, ७; ६, १०; २५, ९; २७, ३; ३२, १२; ३३, ७; ४४, ६; ७८, ७; ८; ८६, ६; **६.** ३, २; ४, १; १७, ३; १३; १९, २; २१, ६; २३, १०; २५, ९; २९, ६[२]; ३८, ५; ४८, १७; ५०, १५; ५४, १; २; **७.** १८, २; २३, ६; २४, ६; २६, ४; ५; ३१, १२; ३३, ३; ४१, ५; ४२, ६; ४३, ५; **८.** २, ३१; ९; १०; २४, १६; २३; ३३, १८; ३८, ९; ४०, १२; ४२, २; ४७, १७; ५३, ८; ५४, २; ५८, २[२]; ६०, ७; ९२, २८[२]; २९; **९.** ६, ९; ६७, ३०; ६८, १०; ७९, ५; ८२, ५; ९०, ६; ९१, ६; ९६, १२; ९७, १५; २१; २७; ३६; १०९, ३; **१०.** ७, ६; १०, १३; १६, ९; १८, ५; ९; १९, ३; २०, १०; २७, ५; २८, ६; ३०, ६; ४४, ४; ६; ७[२]; ४९, ११; ५१, ४; ६०, ८; ६३, १७; ६४, १६; ८२, ३; ८३, २; ८५, ४२; ८९, १७; ९०, २; ९४, १२; ९५, १६; ९९, १२; १००, १०; १०७, ५; ६; १०८, ९; १०९, ३; ११३, ४; ११५, ७; १२०, ९[२]; १२४, १; १२५, ५; ८; १४४, ६; १४५, ४; १४९, ५; १५४, १; १६१, २; १६६, ३; १७३, २.

एवऽथा **८.** २४, १५.

एवं **१०.** १५१, ३.

एवऽया **५.** ४१, १६.

एवऽयाः **१.** १५६, १.

एवयामरुत् **५.** ८७, १–९.

एवंऽयावः **१.** ९०, ५.

एवऽयावः **७.** १००, २.

एवयावंऽभिः **१०.** ९२, ९.

एवऽयावरी **६.** ४८, १२.

एवऽयाम्नः **२.** ३४, ११.

एवऽवदस्य **५.** ४४, १०.

एवाः **५.** ४१, ५; १३.

एवान् **५.** ५१, २.

एवारे **८.** ४५, ३८.

एवासः **१.** १६६, ४.

एवेन **१.** १२८, ३.

एवैः **१.** ६२, ८; ६८, २; ७९, २; ९५, ६; १००, २; ११; १८; ११७, १४; १५८, ३; १८१, ६; **३.** ३३, ५; ५४, ९; ५८, ४; **४.** २, १२; ३३, १; ५६, १; **५.** ४१, ५; **७.** ६, ६; ६२, २; १०४, ७; ९; **८.** १८, १३; ६८, ४; ९७, ३; १०३, १३; **१०.** ६, ६; ८, ७; ६७, ११; ७३, २.

एवो इति **४.** १२, ६.

एषऽएष्यो **१०.** १०२, ११.

एषः **१.** ५६, १; १३९, ७; १६२, ३; १६५, १५; १६६, १५; १६७, ११; १६८, १०; १७१, २; १७३, १३; १८४, ५; **२.** ४, २; १२, ५; १४, १; २; ३६, ५; **३.** ३१, १६; ४२, ८; ४८, ४; ५१, ९; **४.** २, ५; १५, ९; २५, ६; ३५, ४; ४५, १; **५.** ३१, १०; ३६, ४; ४२, १५; १६; ५०, ५; ६१, १९; **६.** ४१, ३; ७३, ३; **७.** २०, ९; २४, ५; ६०, २; ६३, ३; ६४, ५; ६७, ७; ६८, ९; १००, ३; ४; १०१, ३; **८.** १, ३२; २, ३१; ३४ १६, ६; २४, ३०; २९, ६; ६६, १५; १०३, १२; **९.** ३, १–१०; १५, १–६; २७, १–६; २८, १–६; ३८, १; ४–६; ४२, २; ६२, ११; १३; ६६, २९; ६७, २०; ७७, १; ८४, ४; ८७, ४; ७; ९६, १५; ९७, ४६; ४७; ५६; १०८, ५; ११०, ११; **१०.** १६, ८; ७१, ५; ८६, २१; १३९, २; १४६, ४[२]; १६०, ४; १६५, ४; १६८, ४.

एषस्य **२.** ३४, ११; **७.** ४०, ५; **८.** २०, ३.

एषा **१.** ४८, ७; ८८, ६; ११३, ७; १२४, ३; ६; **४.** ३, ९; **५.** ८०, २–६; **६.** ६५, १; **७.** ७५, ४; ७६, ७; ८०, २; ९५, १; **८.** २७, १८; **९.** ८७, ८; **१०.** ११, ८; १४, २; १८, १०; ३१, ६; ३४, २; ८५, २१; २९; १०९, ३.

एषां **१.** १६५, १३; **१०.** ८५, २.

एषां **१.** २४, ७; ३७, ३; १३; १५; ३८, ८; १२; ४१, ३; ४८, ४; ५४, ९; ६१, १५; ६४, ४; ६८, १; ८४, १६; ८५, ३; ८७, ३; ९४, १२; ९७, ३; १२७, ७;

१३४, ६; १५२, २; १६४, ४४; १६५, १०; १६७, २; ७; १६८, ३; १६९, ६; १८५, ८; १८६, ९^{2}; **२.** १५, ८; २७, ८; **३.** १३, ३; ३१, ३; ९; १०; ३९, ४^{2}; ५४, ५; **४.** १, १४; २, ४; २७, १; ३३, ९; ४७, २; **५.** १०, ३; १६, ४; २९, १; ३२, ४; ४२, ९; ५२, १५; ५३, १; ११; ५६, ५; ५८, १; ७; ५९, २; ७; ६०, ५; ६१, ३; १४; ६६, ३; ८७, २; **६.** २५, ३; ५; ५१, २; ८; ६६, २; ७५, १३; **७.** २, २; ७, ४; १८, ११; १३; २१, ४; ३३, ८; ३४, १९; ३९, २; ५; ५६, २; ६०, १०; ८३, ४; ७; १०३, ५^{2}; ६; **८.** ७, १५; २८; १८, १; २; २०, ११; १४^{2}; २८, ४; ५; ३४, ३; ३९, २; ४१, ७; ४५, २; ४६, १८; ६९, १८; ८३, ७; ९३, ३३; **९.** ५२, ४; ६४, २७; ७३, ३; ७; ९१, ४; **१०.** १८, ४; ५; २७, २३; २८, ३; ३४, ५; ८; ४३, ४; ५६, ४^{2}; ६१, २३; ७१, १^{2}; २; १०; ७४, २; ३; ७५, २; ७७, १; ८७, ४; ८८, ८; ९३, ५; ९; १३; १४; ९४, ६; १०७, १; १२८, ६; १२९, ५; १३१, २; १७४, ५; १९१, ३.

एर्षि १. १२३, १०; **८.** ९१, २; **९.** ५०, २; **१०.** ८, ४; ८६, २१.

एषि १. ५०, ५; ७; ५२, १२; ५३, ७; १६२, २१; **३.** ६१, ६; **५.** १, ९; **७.** ३७, ४; **८.** ९३, १; **९.** ८२, २; ८३, १; ९६, २३; ९७, १४^{2}; ५५; १०६, १४; **१०.** १, ४; १४२, ४.

एषु १. ९, ३; **३.** २, १०; ४१, ४; **५.** २३, ४; **७.** १, २२; ३४, १८.

एषु १. ७७, ५; **३.** ३०, १६; **४.** ३२, १२; **५.** ७, ९; ७९, ६; **६.** ६६, ६; **८.** ६८, १८; **१०.** २७, ६; ९३, १०; १४७, ३.

एषे ५. ४१, ५; ८; ६६, ३; **१०.** ४८, ९.

एषे १. १८०, ४.

एषो इति १. ४६, १.

एष्टां १. १८४, २.

एहिंऽमायासः १. ३, ९.

ऐ

ऐक्षेतां १०. १२१, ६.

ऐच्छः १०. १०८, ५.

ऐच्छाम १०. ५१, ३; ५३, १.

ऐजंन् १. ६३, १.

ऐट्ट ३. ४८, ३.

ऐत् १०. ११३, १.

ऐत् ५. ३०, ९; **१०.** ६१, ८; ७२, ८; ९; ९०, ४.

ऐतं १०. १८, २.

ऐत ४. ३५, ३.

ऐतंन १. ११०, २; ३.

ऐतन १. १६१, ६.

ऐते १०. १३, २.

ऐधाऽइव १. १६६, १.

ऐनोः ४. १६, ७.

ऐनोत् १. ६६, ५.

ऐयेः ५. २, ८.

ऐरंत ४. ४, ६.

ऐरत् २. १५, ८; १९, ६; **३.** ३१, १५; ५५, २०; **४.** ५६, ३.

ऐरंत १०. ७१, १.

ऐरत ७. २३, १; **८.** २०, ४.

ऐरतं १. ११८, ६.

ऐरं ४. २६, ३.

ऐरयः २. १७, ३; **८.** ८९, ७.

ऐरयत् २. १७, १; **८.** ६, १३; ७४, ३.

ऐरयत् १. ७, ३; ५१, ११; **२.** १९, ३; २०, ७; **६.** ५६, ३; **८.** ७६, ३.

ऐरयत ८. १९, २४.

ऐरयतं १. ११२, ५.

ऐरयतं १. ११७, २२; २४; **६.** ७२, ३; **७.** ८२, ३; **१०.** ३९, ९.

ऐरयंत १०. १६९, ३.

ऐरयं ४. ४२, ३.

ऐरयेथां १. १५७, ५.

ऐरयेथां ६. ६९, ८.

ऐळ १०. ९५, १८.

ऐपंत १. १२६, ५.

ओ

ओ इति १. १०४, २; ११३, ११; १३८, ४; १३९, ७; १६५, १४; १७७, ५; १८२, १; **२.** ३४, १५; **३.** ३३, ९; **७.** ४०, १; ५९, ५; **८.** २, १९; ७, ३३; २२, १; **१०.** १०, १; ११७, ५; १७९, २.

ओकः १. ६६, २; १०४, ५; १७३, ११; **२.** १९, १; **३.** ५८, ६; **४.** १६, १५; **५.** ३०, १; ७६, ४; **६.** ४१, १; **७.** ४, ८; २५, ४; ३२, ४; ५६, २४; **८.** ३३, २; **१०.** ११२, ४; ११७, ४.

ओकंसः १. ३०, ९; **७.** ५, ६.

ओकंसि ४. ५०, ८; **५.** ३३, ४.

ओकांसि १. ४०, ५; **२.** ३८, ५.

ओकिऽवांसा ६. ५९, ३.

ओक्यः ९. ८६, ४५.

ओक्यं १. १३२, ५; **८.** ४९, ३; ७२, १४; **१०.** ४४, ९.

ओक्या ८. २५, १७.

ओक्ये १. ९१, १३; **३.** ४२, ८.

ओगणासः १०. ८९, १५.

ओचिषे ८. ८२, २.

ओजः १. ३३, १२; ३९, १०; १०३, ३; १२१, १०; १६०, ५; १६५, १०; **२.** १७, २; २९, २; ३६, ५; **३.** २६, ६; ३२, ३; ९; ३६, ४; ४७, ३; ५३, १९; ६२, ५; **४.** ७, १०; १७, ३; १९, ४; ४१, ४; **५.** ३१, ७; १३; ३२, १०; ३३, ६; ५७, ६; **६.** १८, १५; १९, ६; २६, ७; ३६, २; ४६, ७; ४७, २७; ३०; **७.** ५६, ७; ८२, २; ६; ९१, ४; **८.** ६, ५; ४०, ६; ५०, ८; ९६, ३; १७; ९८, १०; **९.** ९७, ४१; **१०.** ८, ९; ४४, ४; ५४, १; ८३, १; ४; ८४, २; ९५, ११; ११६, ६; १७०, ३; १८०, ३.

ओजःऽदाः ८. ३, २४.

ओजःऽदातमः ८. ९२, १७.

ओजःऽभिः ७. ५६, ६.

ओजसः १. ५२, १२; १०२, ८; ५. ३२, ९; ८. १२, २४; १०. ७३, १०; १५३, २.

ओजसा १. ७, ८; ९, १; ११, ८; १९, ४; ८; ३९, ८; ५३, ७; ५५, २; ५; ६; ५६, ६; ८०, १; २; ११; ८५, ४; १०,१०२, ६; १२७, ३; ४²; १३०, ४; ७²; ९; १३२, ५; १७५, ४; १८७, १; १८८, ४; २. १७, ५; २२, २–४; २४, २; ४; २५, ३; ४; ३. ४५, ५; ५१, १०; ४. ३२, ३; ५. ५२, ९; १४; ५५, २; ५६, ४; ५९, ७; ८१, ३; ८४, ३; ७. ५८, २; ८२, ३; ८. ४, ५; ६, १; १५; २६; ४१; ७, ८; १२, ४; २७; १७, ९; ३२, १४; ३३, ७; ८; ३६, ३; ४०, ५; १०; ५१, ८; ६२, २; ८; ७६, १; ९; १०; ८८, ५; ९२, ६; ९३, २३; ९७, ११; १४; ९९, ३; ९. २, ७; ५, ३; ४; १५, ४; २९, १; ३४, १; ३५, २; ३९, ३; ५३, २; ६४, १८; ६५, १०; १४; १०१, ५; १०६, ७; १०८, ६; १०. ४९, ७; ६५, २; ४; ७; ७५, १; ९६, १०; ९९, ६; १०३, ६; ११३, २; ६; १५३, ३–५.

ओजसे १. ५७, ५; ८. १२, २२; २३; ६१, २; ७५, १०.

ओजस्वन्तं ८. ७६, ५.

ओजांसि १. ८०, १५.

ओजायमानः १. १४०, ६.

ओजायमानं २. १२, ११; ३. ३२, ११.

ओजिष्ठ १. १२९, १०.

ओजिष्ठः ६. ३३, १; ८. ९३, ८; ९. ६६, १६; ६७, १; १०१, ९; १०. ७३, १.

ओजिष्ठं ३. २१, ५; ४. ४१, ४; ५. १०, १; ६. १९, ६; ४६, ५; ८. ४, १०; ३४, १६; ९७, १०.

ओजिष्ठया १. १६९, ४.

ओजिष्ठेन १. ३३, ११.

ओजिष्ठेभिः ४. २०, १.

ओजीयः २. ३३, १०; १०. १२०, ४.

ओजीयान् ६. २०, ३; ९. ६६, १७.

ओज्मानं ६. ४७, २७.

ओणिं १. ६१, १४.

ओण्योः ९. १६, १; ६५, ११; १०१, १४.

ओतवे १०. १३०, ५.

ओतवै १. १६४, ५.

ओतुं ६. ९, २; ३.

ओदती १. ४८, ६.

ओदतीनां ८. ६९, २.

ओदनं ८. ६९, १४; ७७, ६; १०.

ओपशः १०. ८५, ८.

ओपशं ८. १४, ५; ९. ७१, १.

ओपशंऽइव १. १७३, ६.

ओमना ७. ६९, ४.

ओमन्ऽवन्तं १०. ३९, ९.

ओमऽभिः ५. ४३, १३.

ओमात्रां १०. ५०, ५.

ओमानं १. ३४, ६; ११८, ७; ६. ५०, ७; ७. ६८, ५.

ओमासः १. ३, ७.

ओम्याऽवती १. ११२, २०.

ओम्याऽवन्तं १. ११२, ७.

ओष १०. ८७, १२; ११८, ८.

ओषः १. १७५, ३.

ओषन्तं ७. १०४, १.

ओषतात् ४. ४, ४.

ओषति १. १३०, ८²; ८. १२, ९.

ओषधयः १०. १७, १४; ९७, १७; २२.

ओषधिः १. १६६, ५.

ओषधिं १०. ८५, ३; १४५, १.

ओषधीः १. ९०, ६; ९१, २२; ९८, २; १०३, ५; १६३, ७; ३. ३४, १०; ५१, ५; ५४, २१; ४. ३३, ७; ५७, ३; ५. ४१, ८; ११; ४२, १६; ४३, १३; ६२, ३; ८३, ४; ५; १०; ६. २१, ९; ३९, ५; ४९, १४; ७. ४, ५; ३४, २३; ३५, ५; १०१, ५; ८. २७, २; ४३, ७; ९; ५९, २; १०. ५८, ७; ६५, ११; ६६, ९; १०; ८८, २; १०; ८९, १३; ९१, ५; ६; ९७, १; ३; ४; ६; ७; १०; ११; १८; १६९, १.

ओषधीः १०. ९७, १२.

ओषधीनां १. १६४, ५२; १८७, ८; ३. १, १३; ७. १०१, १; २; १०२, २; १०. ५१, ८; ८७, १८; ९७, ८.

ओषधीभिः ३. ५, ८; ५. ८, ७; ६. ५२, ६; ७. ८, २; ९. ११२, २; १०. ३०, ५.

ओषधीभ्यः २. १, १; ७. ५०, ३; ९. ११, ३; ५९, २.

ओषधीषु १. ५९, ३; ९१, ४; १०८, ११; २. ४, ४; ३. २२, २; ५. ८३, १; ६. ३, ७; १२, ३; ७. ५६, २२; ६१, ३; ७०, ३; ४; ८. ९, ५; ९. ८४, ३; १०. १, २; १६, ३; ५१, ३; ७३, ९; १८३, ३.

ओषधे १. १८७, १०; १०. ९७, २३.

ओषं १०. ११९, १०.

ओष्ठौऽइव २. ३९, ६.

ओहते २. २३, १६; ५. ४२, १०; ७. ६६, १२; ८. ५, ३९; ४०, ११; ५९, २; १०. ६५, १०.

ओहते १. १७६, ४; ५. ५२, १०; ११²; ७. १६, ११; ८. ३, १४; ७, ३१; ६९, १४.

ओहऽब्रह्माणः १०. ७१, ८.

ओहं १. ६१, १.

ओहसा ६. ६७, ९.

ओहसानं ६. १७, ९.

ओहसे १. ३०, ४; ८. ८०, ९.

ओहानः ६. ५२, ५.

ओहानं ५. ३०, ६.

ओहिषे ८. ५, ३.

ओहैन १. १८०, ५.

ओहैः ४. १०, १.

औ

औक्षत १०. ५५, ७.

औक्षन् ३. ९, ९.

औक्षन् १०. ९०, ७.

औक्षीः १०. २७, ७.

औचथ्यः १. १५८, १.

औचथ्यं १. १५८, ४.

औच्छः ५. ७९, २; ३; १०. ५५, ४.

औच्छत् ५. ३०, १४.

औनत् १०. १४९, २.

औब्जः १. ५६, ५; २. २३, १८.

औब्जत् १. ८५, ९.

औभ्नात् ४. १९, ४.

और्णऽवाभं २. ११, १८; ८. ३२, २६; ७७, २.

और्णोः ६. १७, ६.

और्णोः ७. ७९, ४.

और्णोत् १०. ८१, २.

और्णोत् १. ६८, ५.

और्वभृगुऽवत् ८. १०२, ४.

औलानं १०. ९८, ११.

औशानं १०. ३०, ९.

औशिजः १. १८, १; ११९, ९; १२२, ४; ५; ६. ४, ६; १०. ९९, ११.

औशिजस्य ४. २१, ६; ७; ५. ४१, ५.

औशिजाय १. ११२, ११.

औहत् १०. ६१, ५.

औहत १. १६४, २९.

औहिष्ट ६. १७, ८.

क

कः १. २४, १; ३०, २०; ३५, ७; ३७, ६; १३; ४०, ७^{2}; ५४, ५; ६५, ३; ७१, ५; ७५, ३^{3}; ७६, १; ८०, १५; ८१, ५; ८४, १६; १७^{3}; १८^{2}; ९५, ४; १०५, ४; ११६, ३; १२०, १; १२५, ७; १५२, ३; १५८, २; १६१, १३; १६४, ४^{2}; १८; ४८; १६५, २; १३; १६८, ५; १७०, १; १७३, ११; १८२, ३; ७; १८५, १; २. १६, ३; ३. ३०, १; ५४, ५^{2}; ४. ४३, १; २; ४; ४४, ३; ५५, १^{3}; ५. ३०, १; ३२, ९; ४१, १; ४२, ६; ५३, १^{2}; २; ५९, ४^{2}; ६१, १४; ६७, ५; ७४, २; ७^{3}; ६. २१, ४^{2}; २२, ४; ४७, १; १५^{3}; १९; ५९, ५; ७. ३२, १४; ८. १, २०; ३, १४; ७, २०; ३१; १८, १३; ३३, ७; ४५, ३७^{2}; ६०, ७; ६४, २; ७; ८; ६६, १३; ९६, ९; १००, ३; १०. १०, ६^{2}; १२, ५; २७, ११; २९, ३; ३१, ७; ४०, १; २; १४; ५१, २; ६२, ९; ६३, ६^{2}; ६४, १; ८५, ३; ८८, १७; ९२, ८; ९५, १२; १०२, १०; १०८, ५; ११४, ७; ९^{2}; १२९, ६; १३५, ५^{3}; १५५, ५.

कुः १. ७२, १; ६. २०, ५; ७. ७५, ८; ८. ४५, ३१; ९. ९२, ५; १०. १०, ५.

ककर्दवे १०. १०२, ६.

ककुत् ८. ४४, १६.

ककुत्ऽमान् १०. ८, २; १०२, ७.

ककुभः १. ३५, ८; ४. १९, ४; ८. २०, २१; ४१, ४.

ककुभं ७. ९९, २.

ककुभा ५. ४४, २.

ककुहः १. १८१, ५; ३. ५४, १४; ५. ७३, ७; ७५, ४; ८. ६, ४८; ९. ६७, ८.

ककुहं ८. ४५, १४.

ककुहाः १. १८४, ३.

ककुहान् २. ३४, ११.

ककुहासः १. ४६, ३; ४. ४४, २.

कक्षः ६. ४५, ३१.

कक्षात् १०. २८, ४.

कक्षीवतः १०. २५, १०.

कक्षीवता १. ११७, ६.

कक्षीवते १. ५१, १३; ११६, ७; ९. ७४, ८.

कक्षीवतः १. १२६, ४.

कक्षीवंतं १. १८, १; ११२, ११; १०. ६१, १६; १४३, १.

कक्षीवान् १. १२६, २; ३; ४. २६, १; ८. ९, १०.

कक्ष्यः ५. ४४, ११.

कक्ष्यऽप्रा १. १०, ३.

कक्ष्यऽप्रां ८. ३, २२.

कक्ष्या ७. १०४, ६.

कक्ष्याःऽइव १०. १०, १३.

कक्ष्याभिः १०. १०१, १०.

कक्ष्येऽइहृति १. १७३, ६.

कंकतः १. १९१, १^{2}.

कटुकं १०. ८५, ३४.

कणुकऽयंतीः १०. १३२, ७.

कण्वः १. ३६, १०; ११; ४८, ४; १३९, ९.

कण्वऽतमः १. ४८, ४; १०. ११५, ५.

कण्वं १. ३९, ९; ४७, ५; ११२, ५; ८. ५, २५; ७, १८; ८, २०; १०. ३१, ११; १५०, ५.

कण्वऽमंतं ८. २, २२.

कण्वऽवत् ८. ६, ११; ५२, ८.

कण्वऽसखा १०. ११५, ५.

कण्वस्य १. ४५, ५; ८. ८, ४; ८; ३४, १.

कण्वऽहोता ५. ४१, ४.

कण्वाः १. १४, २; ३७, १; ४९, ४; ८. २, १६; ६, ३; ८; २१; ३४; ४३; ३२, १; ३४, ४.

कण्वाःऽइव ८. ३, १६.

कण्वानां १. ४७, १०; ८. ८, ३.

कण्वाय १. ३६, १७; ३९, ७; ११७, ८; ११८, ७; ८. ५, २३.

कण्वासः १. १४, ५; ४४, ८; ४७, २; ४; ८. २, ३८; ४, २; ५, ४; ६, ३१; ७, ३२.

कण्वासः १. ४६, ९.

कण्वे १. ३६, ८; ११; १९; ८. ४९, १०.

कण्वेभिः ८. ३३, ३.

कण्वेषु १. ३७, १४; ८. ४, ३; ९, १४; ४९, ५.

कत् १. ३८, १; २; ४३, १; ७४, ७; १०५, ५^{2}; ६^{3}; १२१, १; १६१, १; १८१, १; १८५; ८; २. २७, १४; ३. ५८, ४; ४. ३, ५^{3}–७^{3}; ५, १२; १३; १२, ४; २३, २^{2}; ५^{2}; ५. ४१, ११; ४८, १; ८२, २; ६. १५, १; ४६, ८; ४७, ३; ७१, ५; ८. ३, १३; १४^{2}; ४, १८; २१, १; ३३, ७; ६६, ९; १०^{2}; ६७, ५; ८४, ५; ९३, ४; ९४, ७; ८; १०. १०^{4}, ६; १२, ५; २९, ३; ४^{2}; ९३, ४; ९९, १.

कतमः ४. ४३, १^{२}; २^{२}; ६. २१, ४; १०. ५१, २; ६४, १^{२}.

कतमत् १०. ८१, २; १२८, ४; १६८, ३.

कतमस्य १. २४, १; १०. ४०, १४; ६४, १.

कतमा ४. ५१, ६.

कतमां १. ३५, ७.

कतमासु १०. ४०, १४.

कतरः ६. ६९, ८; १०. २७, ११; ८८, १७.

कतरा १. १८५, १^{२}.

कतऽअर्था १०. २२, ६.

कति ९. ७२, १; १०. ८६, २०; ८८, १८^{४}.

कतिथः १०. ६१, १८.

कतिधा १. ३१, २; १०. ९०, ११.

कत्पयं ५. ३२, ६.

कथं ५. ६१, २; १०. १०८, १.

कथा १. ४१, ७; ५४, १; ७७, १; १२०, १; १४७, १; १८५, १; ४. ३, ५^{३}; ७; ८^{२}; ५, १; १३, ५; २३, १; ३^{३}; ४; ५^{२}; ५. ४१, ११; १६; ५३, २; ६१, २; ८. ७०, १३; ८६, २; १०. २८, ५; ६४, १; ४; ८१, २; १४६, १.

कथो इति ५. २९, १३.

कदा १. ८४, २०; १०५, ३; १३९, ५^{२}; ६. ५४, ९; १०. ४८, ५; १५२, १.

कदा १. २५, ५; ३४, ९; ८४, ८^{२}; १५०, २; ३. ५३, ४; ४. ३, ४^{२}; ५, १३; ७, २; २३, ६; ५. ३, ९^{२}; ६. २१, ३; ३५, १^{४}; ३^{२}; ७. ८, ३; २९, ३; ३७, ५; ६; ८६, २^{२}; १०४, ७; ८. ३, १४; ५, २२; ७, ३०; १३, २२^{२}; ३३, २; ४०, २; ५१, ७; ५२, ७; १०. ९५, १२; १०५, १.

कद्रीची १. १६४, १७.

कद्रुवः ८. ४५, २६.

कधऽप्रियः १. ३८, १.

कधऽप्रिये १. ३०, २०.

कनायाः १०. ६१, ५; १०; २१.

कनिक्रत् ९. ६३, २०.

कनिक्रदत् १. १२८, ३^{२}; १५२, ५; २. ४२, १; २; ४. ५०, ५; ५. ८३, १; ९; ९. ३, ७; ५, १; १३, ८; २५, २; २८, ४; ३०, २; ३३, ४; ३७, २; ६३, २९; ६७, ३; १४; ७६, ५; ७७, ५; ८५, ५; ८६, २२; ३३; ९६, २०; २१; ९७, ३२; १०१, १६; १०६, ६; १०; १०. १, २.

कनिक्रदतः २. ११, ९.

कनिक्रंति ९. ४३, ५; ९५, १.

कनिष्ठः ४. ३३, ५.

कनिस्कन् ७. १०३, ४.

कनीनः ३. ४८, १; ८. ६९, १४; १०. ९९, १०.

कनीनःऽइव १. ११७, १८.

कनीनकः १०. ४०, ९.

कनीनकाऽइव ४. ३२, २३.

कनीनां १. ६६, ४; ११६, १०; १५२, ४; १६३, ८; २. १५, ७; ५. ३, २.

कनीयः ४. २४, ९^{२}.

कनीयसः ७. २०, ७; ३२, २४; ८६, ६.

कनीयान् ४. ३३, ५.

कन्यनां ८. ३५, ५.

कन्या १. १६१, ५; ३. ३३, १०; ६. ४९, ७; ८. ९१, १; ९. ५६, ३; १०. १०७, १०.

कन्याऽइव १. १२३, १०.

कन्याःऽइव ४. ५८, ९.

कन्यासु ९. ६७, १०.

कपनाऽइव ५. ५४, ६.

कपर्दिनः ७. ८३, ८.

कपर्दिने १. ११४, ५; ६. ५५, २.

कपर्दिने १. ११४, १; ९. ६७, ११.

कपर्दी १०. १०२, ८.

कपिः १०. ८६, ५.

कपिलं १०. २७, १६.

कपृत् १०. ८६, १६; १०१, १२.

कपृथं १०. १०१, १२.

कपोतः १०. १६५, १–४.

कपोतःऽइव १. ३०, ४.

कपोते १०. १६५, ५.

कबंधिनः ५. ५४, ८.

कं १. ३०, २०; ३२, १४; ३९, १^{२}; ७; ८१, ३^{२}; ८७, ६; ८८, २; ३^{२}; १०२, २; १०९, ३; ११३, ८; १२३, ११; १२४, ६; १२९, ३; १०^{२}; १३२, ४; १६४, १७; १८२, ५; ७; २. १३, १२; ४. ३०, ६; ४३, २; ५. २, २; ७४, ३^{३}; ८३, १०; ६. ९, ५; २१, ४; २९, ३; ७५, १६; ७. ५७, ३; ८७, ५; ८८, ३; ८. १९, १५; ३१, ९; ३६, १; ३९, ३; ६१, १८; ६४, ९^{२}; ७५, ७; ८२, ५; ९४, २; ९५, ३; ९. ८, ५; ४५, १; ३; ६२, २०; ७०, ६; १०४, ६; १०५, ६; १०६, ८; ११०, ५; १०. ५, ५; १३, ४^{२}; ५२, ३; ६०, ८; ७६, ७; ८२, ५; ८६, २२; ८८, १; १०; १८; ९९, १; ११४, ९; १६१, १.

कं १. ४७, १०; ७२, ८; ९८, १; १५४, १; १९१, ६; २. १८, ३; २८, ८; ३७, ५; ३. ५३, २; ६. ५१, १४; ७. ३३, ३; ५९, ५; ८. ११, १०; ४४, २४; ६६, ९; ९. ४९, ४; १०. ५०, ५^{२}; १००, ५; १५७, १.

कमऽद्युवं १०. ६५, १२.

कमयध्वे २. १४, ८.

कयस्य १. २७, ८; १२९, ५; ८. २५, १५.

कया १. १६५, १^{२}; ३. ५५, १३; ४. १३, ५; २०, ९; ३१, १^{२}; ४३, ३; ४; ५. १२, ३; ७. ८, ३; ८. ८४, ४; ९३, १९^{२}; १०. २९, ४; ६४, ४.

कर ४. ३३, ५^{२}.

करः १. ८२, १; १२९, १; ६. १८, १४; २२, १०; ८. ८०, ९; ८४, ६.

करः ३. ४१, ६.

करंजं १. ५३, ८.

करंजऽहे १०. ४८, ८.

करणं ५. ३१, ७; ६. १८, १३; ८. १५, ११.

करणा १. ११९, ७.
करणानि २. १५, १; ४. १९, १०; ५. ३१, ६.
करत् १. ४३, २; १७४, ७; २. ५, ८; ३. ५३, १३; ४. १७, २०; २९, ३; ७. ९७, ८; ८. ९१, ४²; ९. ६२, ११; १०९, ९; १०. ७४, ६.
करत् १. २५, १२; ८९, ३; २. ४१, १२; ३. ६२, १४; ४. ३९, ६; ५. ३१, ११; ४४, ८; ४६, ४; ५६, ७; ६. ४८, १५²; ५२, ५; ७. १०२, ३; ८. २, २०; १८, ७; ९; ६६, ४; १०. ६३, ६; ६४, १; १७३, ६; १८२, १.
करतः ८. १८, ८; १०. ४०, २.
करतं ७. ६५, २.
करतां १. २३, ६.
करतां ४. ५५, ३.
करति १. ४३, ६; २. ३५, १; ४. २२, १; ६. १०, १; ७. १७, ४; १०. १८, ६; ९९, १२.
करते ७. ८८, १.
करते ४. १६, १; ४४, ३; ५. ४२, १०.
करथः १. १३६, ४; ६. ५०, ३.
करन् १. १८६, २.
करन् ५. ३०, ९; १०. ९५, १.
करंति १०. ४८, ७.
करं १०. ४८, ९; ४९, ८; ८५, २५.
करंभऽअत् ६. ५६, १.
करंभः १. १८७, १०.
करंभं ३. ५२, ७; ६. ५७, २.
करंभिणं ३. ५२, १.
करसि १०. १६, २.
करसि ६. ३५, १.
करसे ३. ४३, ५.
करसे १०. २९, ४.
करस्ने १. १६१, १२.
करस्ना ३. १८, ५; ६. १९, ३.
करा १. ११६, १३.
करांसि ४. १९, १०.
कराणि १०. ५२, ५.
कराणि ७. ८६, ७.
कराम ७. ५७, ४.
करामहे ९. १०८, १४; १०. ५९, २.
करामहे १. २५, ५; ८. २२, ३; १०. २३, ६; ३८, ४; ३९, ५.
करिक्रत् १. १३१, ३; ३. ५८, ९.
करिक्रतः १. १४०, ५.
करिति कः ५. २९, ५; ६. २३, ५.
करिति कः १. ६१, ११; ६३, ७; १६२, २०; १६४, ४९; १७४, ७; १८६, ५; २. १८, ४; ३. ५, ७; ३१, ६; ३३, ८; ४. १८, १; २१, १०; २८, १; ५. २९, ४; ६. २६, ५; ४४, १८; ७. २१, ३; २२, ६; ४३, ३.
करिष्ठः ७. ९७, ७.
करिष्यतः २. २४, १४; ४. ३१, ९; ८. ६२, ३.
करिष्यति १. १६४, ३९.
करिष्यथ १. १६१, २.
करिष्यन् ६. २६, ३; ७. १९, ८; २०, १; ९. ११३, १.
करिष्यसि १. १, ६.
करिष्या १. १६५, ९.
करिष्याः ४. ३०, २३.
करूणस्य १. १००, ७.
करूळती ४. ३०, २४.
करेणऽइव १०. ६७, ६.
कर्कंधु १. ११२, ६.
कर्करिः २. ४३, ३.
कर्णऽगृह्य ८. ७०, १५.
कर्णं ६. ७५, ३; १०. ८०, ३.
कर्णऽयोनयः २. २४, ८.
कर्णऽवंतः १०. ७१, ७.
कर्णऽशोभना ८. ७८, ३.
कर्णा ४. २३, ८; २९, ३; ६. ९, ६; ३८, २; ८. ७२, १२.
कर्णाऽइव १०. १०६, ९.
कर्णाभ्यां १०. १६३, १.
कर्णे ५. ३१, ९; ८. ९७, १२; १०. ८६, ४.
कर्णेभिः १. ८९, ८.
कर्णैः १. १८४, ३; २. ३४, ३.
कर्णाऽइव २. ३९, ६.
कर्त १. ९०, ५; ६. ५१, १५.
कर्त १. ८६, ९; १०; १७२, ३; २. २९, १; १०. ६३, ७.
कर्तन २. १४, ९.
कर्तन १. १४२, १२; १६६, १; ७. ४८, ४; १०. ५३, १०; १७५, २.
कर्ते १. १२१, १३; ९. ७३, ९.
कर्तरि १. १३९, ७.
कर्तवे १. ८५, ९; २. २२, १; ९. ८६, २०; १०. ७४, ६.
कर्ता २. ३४, ६; ४. १७, १७; ६. २३, ३; ४; ७. २०, २; ८. ९६, १९.
कर्ता १. १००, ६; ३. ३१, २; ४. १७, ४.
कर्तात् २. २९, ६.
कर्तारं ८. १६, १०.
कर्तृऽभिः १. ५५, ८; ६. १९, १; ७. ६२, १.
कर्ते ९. ७३, ८.
कर्तोः १. ११५, ४; २. ३८, ४.
कर्त्वः १. १६१, ३².
कर्त्वं १. १०, २; २३, १८; २. २४, ३; १०. ६१, ६.
कर्त्वा १. २५, ११; १६१, ३²; ८. १०१, ७; ९. ४७, २; १०. ११३, ७.
कर्त्वानि २. ३०, १०; ४. १८, २; ८. ६३, ६.
कर्त्वेन १०. ४८, ३.
कर्म १. ३१, ८; ६२, ६; १४८, २; १७३, ९; २. २२, १; २४, १४; ३. ३०, १३; ३२, ८; ३३, ७; ३४, ६; ६. ३७, २.
कर्म १. १७३, ४; २. २३, १२; ६. ५१, ७; ७. ५२, २; ६०, ८.
कर्मणः १. ११, ४; १०. ५५, ७.
कर्मणा ३. १२, ६; ६. ६९, १; ७. ३२, १३; ८. ३१, १७; ३९, ५; ७०, ३; ९. ९७, ३३; १०. ५६, ६.
कर्मणिऽकर्मणि १. १०१, ४.
कर्मणे १. ५५, ३.
कर्मण्यः ३. ४, ९.
कर्मण्यं १. ९१, २०.

कर्मन् १. ११२, २; १२१, ११; ८. २१, २.
कर्मनिःऽस्थां १०. ८०, १.
कर्मन्ऽकर्मन् १. १०२, ६; १०. २८, ७.
कर्मऽभिः ३. ३६, १; ९. ४६, ३.
कर्मऽसु ८. ३८, १; १०. १३१, ४.
कर्माणि १. २२, १९; ६१, १३; ८. ३६, ७; ९. ८८, ४; ९६, ११; १०. ५४, ४; ५५, ८.
कर्मारःऽइव १०. ७२, २.
कर्वरे ६. २४, ५.
कर्वरा १०. १२०, ७.
कर्षे ५. ८३, ७.
कर्षत् १०. २८, १०; ११.
कर्षथः ८. २२, ६.
कर्हि ५. ७४, १०; ६. ३५, २; ८. ७३, ५²; १०. ८९, १४.
कलयः ८. ६६, १५.
कलश १०. ३२, ९.
कलशः ३. ३२, १५; ६. ६९, ६.
कलशे १. ११७, १२; ४. २७, ५; ९. ६२, १९; ८६, ११; ९७, ४; ३३; १०६, ७.
कलशस्य १०. १६७, १.
कलशा ६. ६९, २.
कलशाः ९. ६५, १४.
कलशान् ९. ६०, ३; ७५, ३; ८१, २; ८६, १९; ८८, ६; ९२, ६; ९६, २२; १०६, १२; १०. १६७, ३.
कलशानां ४. ३२, १९.
कलशे ६. ४७, ६; ९. ६३, ३; १३; ६७, १५; ७२, १; ८५, ५; ७; ८६, १६; २२; ९३, २; ९६, ९; १४; २४; ९७, २२.
कलशेषु ९. ८, ६; १२, ५; १७, ४; १८, ७; ६७, १४; ६८, ९; ८४, ४; ८६, ६; ९; ३५; ४७; ९६, २३.
कलां ८. ४७, १७.
कलिं १. ११२, १५.
कलेः १०. ३९, ८.
कल्पय १०. १८, ५.
कल्पयतु १०. १८४, १.
कल्पयंतः ८. ५८, १; १०. ११४, ६.
कल्पयंति १०. ११४, ५.
कल्पयस्व १०. १०, १२; १५, १४.
कल्पयाति १०. २, ४.
कल्पयाति १०. २, ३; ५२, ४.
कल्पयावहै १०. ८६, २१.
कल्पस्व १. १७०, २.
कल्पेषु ९. ९, ७.
कल्मलीकिनं २. ३३, ८.
कल्याण १. ३१, ९.
कल्याणीः ३. ५३, ६.
कल्याणीभिः १०. ३०, ५.
कल्याण्यः ४. ५८, ८.
कवऽअरिभ्यः १०. १०७, ३.
कवलवे ७. ३२, ९.
कवंधं ५. ८५, ३; ८. ७, १०; ९. ७४, ७.
कवयः ५. ५७, ८; ७. ५९, ११.
कवयः १. ३१, १; १०२, १; १४६, ४; १५९, ४; १६३, १२; १६४, ५; २. २४, ७; ३. ८, ४; ३४, ७; ५१, ७; ५४, १०; ४. २, १२; ३६, ७; ५. ४५, ४; ५२, १३; ७७, १; ७. ५३, १; ७६, ४; ८६, ३; ८७, ३; ९. ७२, ६; ७३, ७; ९७, २९; ५७; १०. ५, २; ६; ८८, १३; १०१, ४; ११४, २; ५; ६; १२४, ९; १२९, ४; १५४, ५; १७७, १; २.
कवयः १. १८५, १; ३. ५४, १७; ५. ५८, ३; ६. ४९, ६; ११; १०. ५३, १०; ८८, १८.
कवये ४. २, २०; ३, १६; २५, २; ५. १, १२; १५, १; ६. १५, ११; २०, ४; १०. ४९, ३.
कवषं ७. १८, १२.
कवऽसखः ५. ३४, ३.
कविः १. ११, ४; १२, ६; ३१, २; ७१, १०; ७६, ५; ७९, ५; ९१, १४; ९५, ४; ८; १४९, ३; १५१, ७; १६४, १६; १७४, ७; १८८, १; २. २३, १७; ३. २, ७; ३, ४; ११; २३, १; २९, १२; ५४, ६; ४. १५, ३; १६, ३; ११; २६, १; ५३, २; ५. १, ६; ५, २; ११, ३; ३१, १०; ४४, ७; ४५, ९; ८१, २; ६. ७, ७; ३२, ३; ४९, ४; ७. ४, ४; ९, ३; १८, २; ८; ८. ८, ११; ३९, १; ९; ४१, ५; ४४, १२; २१; ६०, ३; ५; ७५, ४; ९. ७, ४; ९, १; १२, ४; ८; १४, १; १८, २; २०, १; २५, ३; २७, १; ४४, २; ४७, ४; ५९, ३; ६२, १४; ३०; ६४, ३०; ६८, ५; ७१, ७; ७४, २; ७८, २; ८२, २; ८४, ५; ८५, ९; ८६, २०; २६; ९२, २; ९४, ३; ९६, १७²; ९७, २; १०७, ७; १८; १०९, १३; १०. २०, ४; ६४, ४; १६; ८७, २१; ९१, ३; ९२, १२; १००, ६; ११०, १; १२४, ७.
कविऽक्रतुः १. १, ५; ६. १६, २३; ९. ९, १; २५, ५; ६२, १३.
कविऽक्रतुं ३. २, ४; २७, १२; ५. ११, ४; ८. ४४, ७.
कविक्रतो इति कविऽक्रतो ३. १४, ७.
कविऽछदा ३. १२, ३.
कविऽतमः ३. १४, १; ७. ९, १.
कविऽतमं ५. ४२, ३; ६. १८, १४.
कविऽतमस्य ५. ८५, ६.
कविऽतरः ७. ८६, ७.
कविऽस्वना ८. ४०, ३.
कविऽस्वा १०. १२४, ७.
कविना ६. ४९, १०; ९. ३७, ६.
कविऽप्रशस्तः ५. १, ८.
कविऽभिः १. ७६, ५; ३. १, ५; ८, ९; ३१, १६; ६. ३२, ३; ९. ७४, ९; १०८, १२.
कविं १. १२, ७; ११४, ४; ११६, १४; १२८, ८; २. २३, १; ३. २, १०; १९, १; २९, ५; ४. २, १२; १६, ९; ५. ४, ३; १४, ५; ६. ७, १; १५, ७; २६, ३; ४९, ४; ७. ६, २; ८. ४४, २६; १०२, ५; १७; ९. ६३, २०; ७२, ६; ८६, २५; १०२, ६; १०. ८८, १४; ९९, ९.

कविंऽईव ८. ८४, २.
कविऽयन् ९. ९४, १.
कविऽयमानः १. १६४, १८.
कविऽवृधः ८. ६३, ४.
कविऽशस्तः १. १५२, २; ३. २१, ४; २९, ७.
कविऽशस्ताः ६. ५०, १४; १०. १४, ४.
कवी इति ८. ८, २.
कवी इति १. २, ९; १३, ८; १४२, ८; १८८, ७; ८. ८, २३; ४०, ३; १०. ४०, ६.
कवी इति १. ११७, २३; ८. ८, ५.
कवीन् १. १६४, ६; ३. ३८, १.
कवीनां २. २३, १; ३. १, २; ३८, २; ५६, ५; ५. ४२, ३; ६. १८, १४; ३२, २; ९. ६४, १०; ६७, १३; ९६, ६; १८; ९७, ३२; १०. २२, १०; ११२, ९.
कवे १. १३, २; १३०, ९; १७५, ४; २. १, १३; ६, ७; ३. २८, ४; ४२, ६; ५२, ६; ५. २१, ३; २६, ३; ६. १६, ३०; ५३, ५; ७; ८. ४४, ३०; ४५, १४; १०२, १८; ९. २५, ६; ६२, २७; ६४, २४; ६६, ३; १०; ८६, १३; २९; १००, ५; १०. १४०, १.
कवेः २. २८, १; ६. ३९, १; ९. १०, ८; १०. ५, ३.
कव्यता १. ९६, २.
कव्यैः ९. ९१, २; १०. १४, ३; १५, ९.
कशःऽजुवं १. ११२, १४.
कशऽप्लकौ ८. ३३, १९.
कशया १. १५७, ४; १६२, १७; १६८, ४; ५. ८३, ३.
कशा १. २२, ३; ३७, ३; ८. ३३, ११.
कशाऽवती ८. ६८, १८.
कशाऽवंता ८. २५, २४.
कशीकाऽइव १. १२६, ६.
कशुः ८. ५, ३७.
कश्यप ९. ११४, २.
कस्मिन् १. ७५, ३; ४. १६, १७; ५. ७४, २; १०. २२, १.
कस्मै १. ८४, १८; १२०, ८; ५. ५३, २; १२; १०. १२१, १.
कस्य १. २४, १; ३९, १; ४२, ४; १६५, २; १६९, ५; ४. ३, १३; २३, १; २५, ३; ४३, १; ५. ३८, ४; ७०, ४; ७४, ३; ६. ९, २; ७. ९४, ८; ८. ६४, ८; ८४, ५; ७; ९३, २०; ९. २९, ५; ७९, २; १०. ४०, ३[2]; ६१, २१; १२९ १.
का १. ७६, १[2]; ७७, १; १२०, १; २. २४, ५; ४२, १; ३. ५४, ५; ४. ५, १३; २०, ९; २१, ९; २४, १; ४३, ४; ७. २९, ३; ८. ५८, १; १०. १०८, १[2]; ३; १३०, ३.
काः ४. २३, ३; ७. ६०, ९.
काकंबीरं ६. ४८, १७.
काकुत् ६. ४१, २.
काकुदः १. ८, ७.
काकुदं ८. ६९, १२.
काचित्ऽकरं १०. ८६, १३.
काटे १. १०६, ६.
काणुका ८. ७७, ४.
काणे १०. १५५, १.
काण्वं ८. २, ४०.
काण्वस्य ८. १, ८; ४, २०; ७, १९; ९, ३.
काण्वायनाः ८. ५५, ४.
कानि १. १०५, ७; ८. १०२, २०[2].
कानिपः ३. २८, ५.
कानीतस्य ८. ४६, २४.
कानीते ८. ४६, २१.
कापया १०. ४०, ३.
कां ७. ८, ३.
कामः १. १७९, ४; २. ३८, ६; ३. ३०, १९; ५४, २; ४. ४३, ७; ५. ४२, १५; ६१, १८; ७. २०, ९; ९७, ४; ८. ७८, ९; ९. ९७, ४६; १०. १०, ७; १२९, ४.
कामऽकातयः ८. ९२, १४.
कामप्रेणऽइव १. १५८, २.
कामं १. १६, ९; ३०, १५; ५३, ३; ५४, ९; ५७, ५; ८५, ११; १४३, ६; १७८, १; २. २०, ४; ३. १४, ५; ३०, २०; ४९, १; ५०, १; ४. २३, ५; ५. ३२, १२; ७४, ५; ६. ५, ७; ४५, २१; ७. ३२, २; ३९, ६; ६२, ३; ८. २, ३९; १९, १८; २४, ६; ६४, ६; ७९, ५; ९९, ४; ९. ८, १; १०. २९, ५; ३४, ६; ४२, ६; ४३, २; ५४, ५; ६१, ६; ६६, १४; ९६, ७; १०६, ११.
कामंऽमूता १०. १०, ११.
कामयंते ६. ७५, ६.
कामयंते ५. ४४, १४; १५.
कामयासे १०. १२४, ५.
कामये १०. १२५, ५.
कामस्य १. ८६, ८; ९. ११३, ११.
कामाः ३. ५५, ३; ४. १६, १५; ९. ११३, १०; ११; १०. २५, २; ४०, १२; ६४, २; ११६, ८.
कामान् १. ८१, ८; ५. ४२, १०; ८. ९८, ७.
कामाय ८. ४३, १८; १०. ९६, ७; ९७, १८.
कामासः ८. २१, ६.
कामिनः ५. ५३, १६; ६. १६, ८; ७. ५९, ३.
कामिने ५. ६१, ७.
कामी २. १४, १.
कामे ३. ४८, २; १०. १२८, २.
कामेन ६. ४९, ८; ५८, ३; ४; ७. १६, १०.
काम्यः १०. २१, ५.
काम्यं १. १८, ६; २. २२, ३; ३८, ११; ४१, १४; ३. ५८, १; ५. १९, ४; ८. ५०, १; ६६, ६; ९. ७२, २; ८५, ४; ९७, २१; १०. ७६, ६.
काम्या १. ६, २; ८, १०; ५. ६१, १६; १०. २१, ६.
काम्याः ३. ३१, १७.
काम्यानि १०. ९५, १०.
काम्यैः १. ६, ८.
कार्यमानः ३. ९, २.
कारः १०. ५३, ११.
कारं १. ११२, १; १३१, ५; ४. १, १४; ५. २९, ८; ९. १४, १.

कारवः १. ११, ६; २. ४३, १; ६. ४५, ३३; ४६, १; ७. ७२, ४; ८२, ४; ८. ३, १८; ४६, ३; ५४, १; ९२, १९; ३३; ९. १०, ६; १७, ६; २९, २; ९२, ५; १०. ६१, १२; ९२, ७.

कारवः ३. ६, १.

कारवे १. ३१, ९; ५३, ६; २. २, ९; ३४, ७; ३. ३३, ९; १०. ६१, २३.

काराधुनीऽइव १. १८०, ८.

कारिणः ३. ५४, १४; ८. २१, १२; ९. १६, ५.

कारिणं ८. २, २९; ६६, १.

कारिणाऽइव ९. १०, २.

कारिणे ९. ९७, ३८.

कारिंपत् ६. ४८, १५.

कारुः १. ८३, ६; १६५, १४; ७. ६८, ९; ९. ११२, ३; १०. ७५, १.

कारुऽधायुः ६. २१, ८.

कारुऽधायाः ३. ३२, १०; ६. २४, २; ४४, १२; १५.

कारुं १. ३१, ८; १०२, ९.

कारू इति ७. २, ७; १०. ११०, ७.

कारून् ४. १६, ३; ५. ३३, ७.

कारे १. १४१, १०; ३. ४९, ३; ८. २१, १२.

कारो इति ३. ३३, ८; १०.

कारोः १. १४८, २; १६५, १५; १६६, १५; १६७, ११; १६८, १०; १७७, ५; १७८, ३; १८४, ४; ३. ३९, ७; ६. २१, ७.

कारोतरात् १. ११६, ७.

कार्पाणे १०. २२, १०.

कार्मारः ९. ११२, २.

कार्ष्मऽइव १. ११६, १७.

कार्ष्मन् ९. ३६, १; ७४, ८.

काले १०. ४२, ९.

काव्यः १०. १४४, २.

काव्यः १. ८३, ५; १२१, १२; ८. ८, ११; २३, १७.

काव्यं ५. ३९, ५; ९. ६, ८; ९७, ७; १०. ५५, ५.

काव्यस्य १. ११७, १२.

काव्या १. ७२, १; २. ५, ३; ४. ११, ३; ५. ५९, ४; ६६, ४; ८. ३९, ७; ४१, ५; ६; ९. ७, ४; २३, १; ५७, २; ६२, २५; ६३, २५; ६६, १; ९४, ३; १०७, २३; १०. २१, ५.

काव्यानि १. ९६, १; ३. १, १७; १८; ४. ३, १६.

काव्यार्यं ६. २०, ११.

काव्ये १. ५१, ११.

काव्येन ३. १, ८; ३६, ५; ४. ३५, ४; ८. ७९, १; ९. ७०, २; ८४, ५; ८७, ३; ९६, १७; १०. २९, ६; ८७, २१; ९१, ३.

काव्येभिः ७. ६६, १७.

काव्येषु ९. ९२, ३.

काव्यैः ५. ३, ५; १०. १३१, ५.

काशिः ३. ३०, ५.

काशिना ७. १०४, ८; ८. ७८, १०.

काष्ठा ८. ८०, ८.

काष्ठाः १. ३७, १०; ५९, ६; ६३, ५; ४. ५८, ७.

काष्ठानां १. ३२, १०.

काष्ठां ७. ९३, ३; ९. २१, ७.

काष्ठायाः १०. १०२, ९.

काष्ठासु १. १४६, ५; ६. ४६, १.

कासु १. १२९, २; ४; ६. २१, ४; ८. ३१, १५.

किः १०. ५२, ३.

किकिदीविना १०. ९७, १३.

किकिरा ६. ५३, ७.

कितव १०. ३४, १३.

कितवः १०. ३४, ६.

कितवं २. २९, ५; १०. ३४, ११.

कितवस्य १०. ३४, ३; ७; १०.

कितवासः ५. ८५, ८.

किं १. २३, २२; ११८, ३; १२२, १३; १६१, १^{३}; १०; १६४, ६; ३९; १६५, ३; १७०, २; ३; १८२, ३^{२}; १९१, ७; २. १६, २; २९, ३^{२}; ३. ५३, १४; ४. ५, ८; १२; १४; १८, ४; ६; ७; २१, ९^{२}; २३, ६; ३०, ७; ५. २, ३; ३०, ९; ३२, १२; ८३, ९; ६. ९, ६^{२}; २०, ४; २२, ४; २७, १^{५}; ४४, १०; ४७, १०; ५२, ३^{३}; ७. ५५, ३; ८३, २; ८६, २; ४; ८९, ५; १००, ६; १०४, १४; ८. ८, ८; २१, ६; ४८, ३^{२}; ७३, ११; ८०, ३; ५; ६; ९. ६९, ६; ११४, ४; १०. ७, ६; १०, ११^{२}; १२, ५; ३१, ७; ३८, ५; ४२, ३; ४८, ७^{२}; ५९, ८; ७९, ६; ८१, २; ८६, ३; ८^{२}; ९०, ११; ९५, २; ११; ९७, १०; १०८, १; ११२, ९; १२९, १^{२}; २; १३०, ३^{४}.

किमीदिना ७. १०४, २३; १०. ८७, २४.

किमीदिने ७. १०४, २.

किंऽमयः ४. ३५, ४.

किंऽयुः ३. ३३, ४.

कियत् ४. १७, १२^{२}; १०. २७, ८.

कियति १. ११३, १०, २. ३०, १.

कियती १०. २७, १२.

कियते ४. ५, ६.

कियांबु १०. १६, १३.

कियेधाः १. ६१, ६; १२.

किर ६. ४६, २; ९. ८१, ३.

किरणः १०. २७, ५.

किरणं ४. ३८, ६; ५. ५९, ४.

किरणाऽइव १०. १०६, ४.

किरणाः १. ६३, १.

किरते ४. ३८, ७.

किरासि ८. ४९, ४.

किल १. ३२, ४; २. १२, १५; ६. ४७, १^{२}; ७. ३३, ४; १०. १०, १३; ९४, १०; ९७, ५; १११, ३; ८; १५९, ४; १७४, ४.

किलास्यः ५. ५३, १.

किल्बिषऽस्पृत् १०. ७१, १०.

किल्बिषात् ५. ३४, ४.

कीकटेषु ३. ५३, १४.

कीकसाभ्यः १०. १६३, २.

कीजः ८. ६६, ३.

कीदृङ् १०. १०८, ३.

कीनाराऽइव १०. १०६, १०.

कीनाशाः ४. ५७, ८.
कीरयः ७. १००, ४.
कीरये ६. २३, ३; ७. ९७, १०.
कीरिः ६. ३७, १; ७. २१, ८; ८. १०३, १३.
कीरिऽचोदनं ६. ४५, १९.
कीरिणः ५. ५२, १२.
कीरिणा १. १००, ९; ५. ४, १०; ४०, ८.
कीरिं १०. ६७, ११.
कीरेः १. ३१, १३; २. १२, ६; १०. ४१, २.
कीर्ति १०. ५४, १.
कीर्तेन्यं १. १०३, ४.
कीलालऽपे १०. ९१, १४.
कीवंतः ३. ३०, १७.
कीस्तासः १. १२७, ७; ६. ६७, १०.
कुक्षयः ३. ३६, ८.
कुक्षये ७. ९२, २४.
कुक्षा ९. ८०, ३; १०९, १८.
कुक्षिः १. ८, ७.
कुक्षी इति २. ११, ११; १०. २८, २; ८६, १४.
कुक्ष्योः ३. ५१, १२; ८. १७, ५.
कुचरः १. १५४, २.
कुटस्य १. ४६, ४.
कुणारुं ३. ३०, ८.
कुंडऽपाय्यः ८. १७, १३.
कुंड्रणाच्याः १. २९, ६.
कुतः १. १३६, १; १६४, १८; १६५, १; ३; १७९, ४; २. २३, ५; ७. १, २; ८२, ७; ८. १९, ६; १०. ३९, ११; १२९, ६[२]; १६८, ३.
कुत्र ५. ७, २; ६. ३, ३; ७. ६९, २.
कुत्सः १. १०६, ६; ४. १६, १०; १०. ४०, ६.
कुत्सऽपुत्रं १०. १०५, ११.
कुत्सं १. ३३, १४; ५१, ६; ५३, १०; ११२, ९; २३; १७४, ५; १७५, ४; ४. २६, १; ५. ३१, ८; ६. १८, १३; ७. १९, २; ८. १, ११; ५३, २; १०. ४९, ३.
कुत्सऽवत्सं १०. १०५, ११.
कुत्सस्य २. १४, ७.
कुत्साः ७. २५, ५.
कुत्सात् १०. ३८, ५.
कुत्साय १. ६३, ३; १२१, ९; २. १९, ६; ४. १६, १२; ३०, ४; ५. २९, १०; ६. २०, ५; २६, ३; ८. २४, २५; १०. ४९, ४; ९९, ९; १३८, १.
कुत्सेन ४. १६, ११; ५. २९, ९; ६. ३१, ३; १०. २९, २.
कुत्स्येन ४. १६, १२.
कुनन्नमा १०. १३६, ७.
कुपयं १. १४०, ३.
कुभन्यवः ५. ५२, १२.
कुभया १०. ७५, ६.
कुभा ५. ५३, ९.
कुमार १०. १३५, ३; ४.
कुमारः २. ३३, १२; ४. १५, ७; ९; ५. ७८, ९; १०. ७९, ३.
कुमारकः ८. ३०, १; ६९, १५.
कुमारऽदेष्णाः १०. ३४, ७.
कुमारं ४. १५, १०; ५. २, १; २; १०. १३५, ५.
कुमाराः ६. ७५, १७.
कुमारात् ४. १५, ८.
कुमारिणा ८. ३१, ८.
कुंभं १०. ८९, ७.
कुंभान् १. ११६, ७; ११७, ६.
कुंभिनीःऽइव १. १९१, १४.
कुंभे ७. ३३, १३.
कुयवं १. १०३, ८; २. १९, ६; ४. १६, १२; ६. ३१, ३; ७. १९, २.
कुयवस्य १. १०४, ३.
कुयवाचं १. १७४, ७.
कुरीरं १०. ८५, ८.
कुरु १०. १९, २; १४५, २.
कुरुंगस्य ८. ४, १९.
कुरुऽश्रवण १०. ३२, ९.
कुरुऽश्रवणं १०. ३३, ४.
कुर्मः १०. ५१, ७.
कुलऽपाः १०. १७९, २.
कुलाययत् ७. ५०, १.
कुलायिनं ६. १५, १६.
कुलिशः ३. २, १.
कुलिशी १. १०४, ४.
कुलिशेन १. ३२, ५.
कुल्फौ ७. ५०, २.
कुल्याः ५. ८३, ८.
कुल्याःऽइव ३. ४५, ३; १०. ४३, ७.
कुवित् १. ३३, १; १४३, ६[३]; २. ५, ५; १६, ७; ३५, १; २; ३. ४२, २; ४; ४३, ५[४]; ४. ५१, ४; ५. ३, १०; ३६, ३; ६. २३, ९; ४२, ४; ७. १५, ४; ५८, ५; ९१, १; ८. २६, १०; ७५, ११; ८०, ३; ९१, ४[४]; ९६, १०; १०३, ९; ९. १९, ५; १०. ६४, १२; १३; ११९, १; १३१, २.
कुवित्ऽसस्य ६. ४५, २४.
कुशरासः १. १९१, ३.
कुशिकस्य ३. ३३, ५.
कुशिकाः ३. ५३, १०; ११.
कुशिकासः ३. २६, १; २९, १५; ३०, २०; ४२, ९.
कुशिकेभिः ३. २६, ३; ५३, ९.
कुपवा ४. १८, ८.
कुपुंभकः १. १९१, १५; १६.
कुह १. २४, १०; ४६, ९; ११७, १२; १८४, १; २. १२, ५; ५. ७४, २[२]; ६. २१, ४; ८. ७३, ४[३]; १०. २२, १; ४०, १; २[४]; १२९, १.
कुहचित्ऽविदे ७. ३२, १९.
कुहुया ८. २४, ३०.
कुहयाऽकृते ८. २४, ३०.
कूचक्रेणऽइव १०. १०२, ११.
कूऽचित् ९. ८७, ८; १०. ४, ५; ९३, ११.
कूचित्ऽअर्थिनं ४. ७, ६.
कूटं १०. १०२, ४.
कूपे १. १०५, १७.
कूलात्ऽइव ८. ४७, ११.
कूळयातः ८. २६, १०.
कूऽस्थः ५. ७४, १.
कूकदाश्वे १. २९, ७.
कूच्छ्रा १०. ५२, ४.

कृच्छ्रेऽश्रितः ६. ७५, ९.
कृणत्ति १०. १३०, २.
कृणव १०. ९५, २.
कृणवः १. ५४, ५; ५. ४, ११; २९, १३; १४; ६. ३५, ३; १०. १६, १.
कृणवः ८. १००, १.
कृणवत् ४. १२, १; ७. २६, ३; ६४, ४; ८८, ६; ८. ६२, ९; १०. ४५, ९; ७०, १०.
कृणवत् ४. १८, ४; ७. ८४, २; ९६, ३; ८. ४८, ३; १०. ७, ६.
कृणवते ४. २, ८; ९; ८. ४७, १५.
कृणवन् ७. ६३, ४; १०. १०, १०.
कृणवन् ४. ५१, १; ५. २, ३; ७. ४८, ३.
कृणवंत १. १७८, २; ७. ३७, ७; १०. ७४, २.
कृणवंते १. ८८, ३.
कृणवं १०. ४९, १.
कृणवसे ६. १६, १७.
कृणवाम १. ९४, ४; १६५, ७; ५. ४५, ६; ८. ६२, ४; १०. २, २; १६५, १.
कृणवाम २. २९, ३; ३. ३५, ५; ४. ३३, ५.
कृणवामहै ८. ६१, ११.
कृणवाव ३. ५३, ३.
कृणवावहै १०. ९५, १.
कृणवै १. १६५, १०.
कृणवै १०. १०८, ९.
कृणु १. ३०, १२; ४२, ७; ३. २९, १२; ६. २, १०; ५३, ७; ९. ८५, ४; १०. ८५, ४५.
कृणुत ५. ४९, ५.
कृणुत ५. ५७, ७; ८. १८, ११; ८०, १०; १०. ३१, ८; १०; ४८, ९; ६७, ११; ७८, ८.
कृणुतः ८. ३१, ९.
कृणुतं १. ९३, १२; ८. ७३, ७.
कृणुतं १. १८२, ३; २. ३०, ६; १०. ३६, ६; ३९, २.
कृणुतात् २. ३०, ५.
कृणुतां २. ५, ७.
कृणुते २. २५, १–५; ४. १७, १०; ५. ६१, ७; ८३, ३; १०. २७, २४; ११७, २.
कृणुते १. ९५, ८; १०; ११३, १५; ११५, ५; ३. ३०, १२; ४. ७, ११; १७, १०; २४, ६; २५, ६; ५३, ३; ५. २, ९; ८३, ३; ८. ४, ६; ६२, ६; ९. ७१, १; २; ८; ७४, ७; ७६, १; ८८, ५; ९५, १; ९७, ९; १०३, २; १०. ४०, २; ४२, ४; १०७, ७; ११७, ३; १६५, ३.
कृणुथ ८. ६७, १७.
कृणुथ ३. ५३, १०; ६. २८, ६^{२}; ८. २७, १८.
कृणुथः १०. ३९, ११; १४३, १.
कृणुथः १. १८२, ३.
कृणुध्वं ७. ३२, ८; ९.
कृणुध्वं १. ७७, २; १२२, ४; १८६, १०; ४. ३, १; ५. ४१, ६; ६. ४९, ६; ७. ३, १; ३१, १०; ३४, ९; ३६, ८; ३९, ३; ५३, २; ८. ७२, १; १०. ६, ५; ३४, १४; ६४, ७; ७४, ५; १०१, २^{३}; ७; ८^{२}.
कृणुषे १. १२३, १०; ११; ६. ६४, २.
कृणुष्व १. १०, ७; ४. ४, १; ८. ६४, १.
कृणुष्व २. २, ६; २६, २^{१}; ४. ४, ५; ५. २८, ३; ७. २५, ४; ८. १९, २०; १०. ६, ६; १०, १४; ८५, २०; १४२, ७.
कृणुहि १. १८, १; १६५, ९; ४. २, २०; ६. १७, ३; २५, ३; ४४, १८; ८. ४८, ६.
कृणुहि १. १३, २; ३१, ८; ३. ६, ६; ३०, ६; ३१, २०; ४७, २; ४. ४, १४; २२, ९; ५. ४२, ९; ४३, ५; ६. ४४, ९; ४८, ४; ५३, १०; ७. १७, ३; २५, २; ८. ६१, १६; ९. ९१, ५; ९४, ५; १०. ५१, ५; ११०, २; १३१, २.
कृणोत ३. २९, ९.
कृणोत १. १६२, १८; ७. ३४, १२; ८. ३२, १७; १०. १२८, ५.
कृणोतन ८. १८, १८.
कृणोतन १. १३, १२; १६१, २; ४. १५, १०; १०. १०१, ५.
कृणोति १. ५५, ५; ७७, १; ४. २०, ९; २४, ६; ५०, ९; ६. ४७, १५; ६०, १०; ६४, १; ७. १८, १८; १०२, २; ८. ३२, ११; १०. ८७, ८; ९७, २२; १६५, ४.
कृणोति १. १८, ८; ४८, ८; ९२, ६; १०५, १५; १७३, ११; ४. १७, १३; ५. ७, ४; ३१, १; ७५, ४; ६. ७५, २; ५; ७. ८१, १; ९. ३, ५; ९५, २; १०. १७, १; ३४, ८; ४८, १०; ११७, ७; १६०, ३.
कृणोतु १. ८४, ३; १०२, ९; १६२, २२; ४. ३९, ३; ६. ४७, १२; ७५, १८; ८. ४५, ९; ९७, १३; १०. १६, ६; ३५, २; ४२, ११.
कृणोमि १. १६२, १९; ४. ४२, ५.
कृणोमि १. ११६, १२; ३. ३१, १९; ७. २२, ७; ९९, ७; १०. ३४, १२; १२५, ५; ६.
कृणोषि १. ३१, ७; ७४, ४; ५. ३, २; ६. १३, ५; ४५, ६; ७. ८१, ४; ९०, २; ८. २१, १४; ६२, ५.
कृणोषि ४. ३२, २.
कृण्महे ७. १६, ४; १०. ८४, ४.
कृण्वत १. ७२, ५; १००, ७; ४. २४, ३.
कृण्वतः ८. ३६, ७; १०३, ३.
कृण्वती १. ९२, ४; ५. ८०, २.
कृण्वते २. ३०, १; ८. ७२, १५.
कृण्वते १. १४०, ७; १६१, ५; ६. ७५, ७; ९. १०१, ८.
कृण्वन् १. ६, ३; ५५, ६; ७०, ४; १०५, १७; ४. १४, २; ७. १०१, १; ८. १४, ८; ९६, २१; ९. ६४, ८; ७८, ५; ८४, २; ८६, २६; ९०, ४; ९६, १; ३; २२; ९७, १०; १४; १६; १०. ८, २; १२, १; १०२, ८; १११, ३; १६८, १.

कृण्वंतः १. ८८, ४; ११७, २५; ७. १, १७; ३७, ४; १०३, ८; ९. ६२, २; ३; ६३, ५.

कृण्वंतं २. २८, ७; ५. २८, २; ८. ३२, १०.

कृण्वंति १. ३८, ७; ९; ४७, २; १२३, ६; ३. ५३, १४; ७. ३३, ७; ९. ३१, १; ६४, २३.

कृण्वंतु ३. ३७, २.

कृण्वंतु १. १६२, १०; १७०, ४; ३. ८, ८; १०. १३७, ६.

कृण्वानः ३. ५३, ८; ४. ३८, ६; ५. ४, ६; ८. ४३, ७; ९. १४, ५; ८६, २६; १०७, २६; १०. ७३, ७; ११३, १.

कृण्वानाः ३. ५८, ६; ५. ३, ८; १०. १०९, ६; १२२, ७; १२४, ७.

कृण्वानासः १. ७२, ९; ३. ३१, ९.

कृण्वाने १०. ६१, ६.

कृण्वीत ४. २१, ५; ८. २३, १९.

कृण्वे १. १३८, २.

कृण्वे ७. ३६, २.

कृण्वैते इति ६. २५, ४.

कृत ६. ५८, ३; ९. ६९, ५; १०. ९७, २.

कृतः १. ५४, ३; १०५, १६; १४१, ८; ६. ४९, ८; ७. ६२, १; ८. ९३, ८; ९. ३, २; १०. ९०, १२; १७६, ४.

कृतद्वंसू इति कृतऽद्वंसू ८. ३१, ९.

कृतऽध्वजः ७. ८३, २.

कृतऽब्रह्मा २. २५, १; ६. २०, ३; ७. ७०, ६.

कृतं १. २४, ९; ३४, ८; ८५, ६; ११२, २४; ११७, ८; १३२, १^{२}; २. २२, ४; ३. ७, १०; २९, १; ४. १०, ७; ५. ६०, १; ६४, ६; ७३, ४; ६. १८, १३; ५१, ८; ५८, ४; ६०, ४; ७४, ३; ७. ८४, ३^{२}; ८. ४, ३; ७; ८, १३; १७; ९, ५; १९, १०; ४५, ३२; ५७, ३; ९. ७१, ६; ९७, ५८; १०. ४०, १३; ४२, ९; ४३, ५; १०२, २; १३५, ६.

कृतं १. १७, ७; १८२, ४; ६. ५९, ८; ७. २, ७; ६७, ५; ८. १८, १६; १०. २४, ६; ३९, २; १४३, ५.

कृतस्यं ७. ११, ४.

कृता १. २८, २; ३. १, २०; ३०, २; ६. ६१, १३; ८. १०, ३; ७७, ९; १०१, १३; १०. ९७, ५.

कृताः ३. ३५, ७; १०. ९०, १५.

कृताःऽइव २. ३५, ५.

कृतात् १०. ६३, ८.

कृतान् १. १६१, ४; १०. ५३, ६.

कृतानि १. २४, १४; २५, ११; १००, ९; ११७, ४; १२८, ७; २. ११, ६; १२, ४; २१, ३; ३. ३८, ९; ५. ३०, ३; ४२, ६; ७. ६, १; १८, १४; ६१, ६; ९८, ५; ८. ३२, १; ६३, ६; ९. ४७, २; १०. ३४, ६; ११२, ८.

कृतिः १. १६८, ३.

कृते ५. १७, १; ७. ५७, ५; १०. ९६, ९; १०१, ३.

कृतेन १०. ४८, ३.

कृतेभिः ८. १६, ६; १०. १११, १.

कृत्तिः ८. ९०, ६.

कृत्वे २. १३, १०.

कृतुः १. ९२, १०; ८. ७९, १.

कृतुं ८. १६, ३.

कृत्वो इति ६. १८, १५.

कृत्या १०. ८५, २८; २९.

कृत्रिमा १. ५५, ६; ८. ६७, २०.

कृत्रिमाणि २. १५, ८; ७. २१, ३.

कृत्वः ३. १८, ४; ५४, १.

कृत्वने ८. २४, २५; १०. १४४, ३.

कृत्वऽसु ९. ६५, २३.

कृत्वी १. १६१, ३; १०. १५, १२; १७, २; १०९, ७; १५९, ४.

कृत्व्यः ६. २, ८; ९. ७६, १; ७७, ५; ८४, ५; १०१, २.

कृत्व्यं १०. ४९, ७; १४४, २.

कृत्व्याःऽइव ९. ४६, १.

कृत्व्यान् १. १२१, ७.

कृत्व्यानां ८. २५, २३.

कृत्व्ये १. ५४, ६; ८. ५, २६; ८, २१; ५०, ९.

कृथ १०. ९७, ९.

कृथः १. ११२, ८; ५. ७४, ५.

कृथः १०. ३९, ८.

कृधि १. १०, ११; ३६, १४; २. ९, ५^{२}; १७, ७; ८; ३. १५, ३; १८, ५; ४. १२, ४; ६. ४७, १०; ५१, १३; ७. १६, ६; ८. २६, २५; ५३, ६; ६७, १२; ९६, ८; ९७, ८; ९. २३, ३; ६१, २८; ८४, १; ९७, २७; १०४, ६; १०. ४२, ७; ९३, ९.

कृधि १. १४, ७; ४२, ६; ५५, ७; ९४, ९; १०२, ४; १०६, ५; ११४, २; १२७, ११; १३८, २^{२}; २. २, ७; २३, ७; ३०, १०; ४१, १६; ३. १, १९; ४, २; १६, ५; ४. १, ३^{२}; ३१, १५; ५. १८, ५; ५१, १४; ६. ५, ६; २३, ७; ४६, ६; ७. २५, ५; २७, ५; ३२, २५; ४२, ५; ७७, ४; ८. १९, १२; ३२, ९; ३६, ६; ५३, ४; ६०, १४; ६१, १३; ६८, १२; ७५, २; ११; ८०, ४–६; ९०, ४; ९१, ६; ९३, १०; ९. ४, १; ६४, १४; ७८, ५; ११३, ८; १०. २२, १५; ३८, २; ८५, ४५; ९६, ११; ११२, १०; १३३, ४; १४२, १; १४७, ५; १५१, २; ३; १६६, १; १६७, १; १७१, ४; १८६, २.

कृधुऽकर्णः १०. २७, ५.

कृधुना ४. ५, १४.

कृध्वं ७. ३४, १५.

कृंतत् ८. ४५, ३०.

कृंतत्रे १०. ८६, २०.

कृंतत्रात् १०. २७, २३.

कृपणंत १०. ७४, ३.

कृपणे १०. ९९, ९.

कृपण्यति ८. ३९, ४.

कृपते १. ११३, १०.

कृपऽनीळं १०. २०, ३.

कृपंत ९. ९९, ४.

कृपमाणं १. ११६, १४; ११९, ८.

कृपऽयुतः ८. ४६, १६.

कृपयंन् १०. ९८, ७.

कृपा १. १२७, १; १२८, २; ६. २, ६; १५, ५; ७. ३, ९; ८. २३, ५; ८; ९. ६४, २८.
कृपीटं १०. २८, ८.
कृपे ८. ४, २.
कृशनऽवतः १. १२६, ४.
कृशनिनः ७. १८, २३.
कृशनेभिः १०. ६८, ११.
कृशनैः १. ३५, ४.
कृशं ६. २८, ६; ८. ७५, ८; १०. ४०, ८.
कृशस्यं २. १२, ६; ८. ५९, ३; १०. ३९, ३.
कृशानुः ४. २७, ३.
कृशानुं १. ११२, २१; १०. ६४, ८.
कृशानोः १. १५५, २; ९. ७७, २.
कृशाय १०. ११७, ३.
कृशे ८. ५४, २.
कृपतु ४. ५७, ४.
कृपन् १०. ११७, ७.
कृपंतु ४. ५७, ८.
कृपस्व १०. ३४, १३.
कृपिं १०. ३४, १३.
कृपे ८. ३, २०; ३२, ३.
कृपे १०. ४९, ७; ५०, ५; ६.
कृष्टयः १. ४, ६; ३६, १९; ५२, ११; ३. ४९, १; ४. ३०, २; ५. १९, ३; ७. ३१, ९; ८. ५, ३८; ६, ४; ७४, १०; ७५, १०; १०३, ३; ९. ६९, ७; ८६, ३७; १०. ५०, ५; ६०, ४; ११९, ६.
कृष्टिऽओजसा ७. ८२, ९.
कृष्टिऽप्रः ४. ३८, ९.
कृष्टिऽभिः १. १००, १०.
कृष्टिषु १. ७४, २; २. २, १०; ३. ५३, १६; ६. ४६, ७; ८. ९२, १८.
कृष्टिहाऽइव ९. ७१, २.
कृष्टीः १. ७, ८; १६०, ५; १८९, ३; ३. ४३, ७; ५९, १; ४. १७, ६; ७; २१, २; ३८, १०; ६. १८, ३; ३१, १; ७. १९, १; ८५, ३; ८. २४, १९; ६२, २; १०. १७८, ३.
कृष्टीनां १. ५९, ५; १७७, १; ४. १७, ५; ५. १, ६; ६. १८, २; ४५, १६; ७. ५, ५; ६, १; २६, ५; ८. १३, ९; ३२, १९; ६८, ७.
कृष्टेः ४. ४२, १.
कृष्णऽअध्वा २. ४, ६; ६. १०, ४.
कृष्णः ८. ८५, ३.
कृष्णाः १. ७९, २; ४. १७, १४; ८. ९६, १३; १०. १६, ६; २०, ९.
कृष्णऽगर्भाः १. १०१, १.
कृष्णऽजंहसः १. १४१, ७.
कृष्णऽपविः ७. ८, २.
कृष्णऽप्रुतौ १. १४०, ३.
कृष्णं १. ५८, ४; ७३, ७; ९२, ५; ११५, ५; १४०, ५; १६४, ४७; ३. ५५, ११; ४. ७, ९; ६. ९, १; ७. ३, २; ८. ९६, १४; १०. १२७, ७.
कृष्णया ८. ७३, १८.
कृष्णऽयामं ६. ६, १.
कृष्णऽयोनीः २. २०, ७.
कृष्णऽवर्तनिं ८. २३, १९.
कृष्णऽव्यथिः २. ४, ७.
कृष्णऽसीतासः १. १४०, ४.
कृष्णस्य ८. ८५, ४.
कृष्णा १. ३५, ४; ११३, २; ४. ३, ९; १६, १३; ६. ६०, १०; ८. ४३, ६; ९. ६६, २४; १०. २१, ३; ६१, ४; ८९, २.
कृष्णाः १०. ९४, ५.
कृष्णाः ६. ४७, २१.
कृष्णात् १. १२३, १; ९.
कृष्णान् ३. ३१, २१; ८. ४१, १०.
कृष्णां १. ११३, १४; १३०, ८; ९. ४१, १; १०. ३, २.
कृष्णाय १०. ३१, ११.
कृष्णासः १. १४१, ८.
कृष्णासु १. ६२, ९; ३. १५, ३; ८. ९३, १३.
कृष्णियाय १. ११६, २३; ११७, ७.
कृष्णीः ७. ७१, १.
कृष्णे इति ३. ३१, १७; ४. ४८, ३.
कृष्णेन १. ३५, २; ९.
कृष्णेभिः १. ६२, ८.
कृत्व १. १०, ९; ६. १८, १५; ७. २२, ४.
कृण्व १. ५४, ९; २. २३, १४; ३. ५२, ५; ६. २१, ९; १०. ४४, ४.
के १. ८७, १; ९४, ९; ११०, २; ३. ४५, १; ५. २, ५; १२, ४[४]; ५२, १२; ६१, १; ६. ५२, १५; ६७, १०; ७. ५६, १; १०३, ८; ८. ४५, ४[२]; ७७, १[२]; ९. ११०, ६; १०. १९, ७; २०, ८; ५०, ३[२]; ५४, ३; ९०, १०.
केतः १. २४, १२.
केतं १. ३३, १; २. ३८, ५; ४. २६, २; ७. १८, २५; ९. २१, ६; १०. ९५, ५.
केतवः १. २४, ७; ५०, १; ३; १९१, ४; ७. ७८, १; ८. १२, ७; ४३, ५; ९. ७०, ३; ८६, ५; ६; १०. ७८, ७; ९१, ५; १११, ७.
केतवे १. १६६, १; १०. ३७, १.
केतऽवेदाः १. १०४, ३.
केतुऽसापः ५. ३८, ३.
केतस्य १०. १३६, ६.
केताः १. ५५, ७.
केतान् १. १४६, ३.
केतुः १. २७, १२; ९६, ६; १०३, १; ११३, १९; १२४, ११; १२७, ६; ३. १, १७; १०, ४; ११, ३; ५५, २; ६१, ३; ५. ११, ३; ७. ६३, २; ६७, २; ७६, २; ९. ८६, ७; १०. ४५, ६; ८५, १९; ८९, १२; ९२, १; ९६, ४; १५६, ५; १५९, २.
केतुना १. ३, १२; ३६, १४; १८७, ६; ५. ४४, ८; ६०, ८; ६६, ४; ६. ७, ६; १०. ८, १; ३७, ९.
केतुं १. ६, ३; ६०, १; ७१, २; ९२, १; ११३, १५; १२४, ५; ३. २, १४; ३, ३; ८, ८; २९, ५; ३४, ४; ४. ७, ४; १४, २; ५. ७, ४; ११, २; ३४, ९; ६. २, ३; ७, २; ५; ३९, ३; ४९, २; ७. ५, ५; ६, २; ९, १; ३०, ३; ३४, ६; ८. ४४, १०; ९६, ४; ९. ६४, ८; १०. १, ५; २, ६; ८८, १२; १३९, २.

केतुऽमत् ६. ४७, ३१.
केतुऽमंतं ८. ५८, ३.
केतू इति २. ११, ६.
केतेन ८. ६०, १८.
केतेभिः ३. ६०, ७.
केनं १. ७६, १; ८७, २; १६५, २; १०. १५, ६.
केऽनिपानां १०. ४४, ४.
केनो इति ८. ६६, ९.
केपयः १०. ४४, ६.
केभिः ८. १०३, १३.
केवटे ६. ५४, ७.
केवलऽअघः १०. ११७, ६.
केवलऽआदी १०. ११७, ६.
केवलः १. ७, १०; १३, १०; ४. २५, ७; ७. ९८, ५.
केवलं १. ५७, ६; ४. ३५, ७; १०. ९६, १३; १४५, २.
केवला ४. २५, ६; ८. ५२, ३; १०. १३८, ६.
केवलान् १०. ५१, ८.
केवलानि १०. ५४, ५.
केवली: १०. १७३, ६.
केवले १०. ५१, ९.
केशऽवंता १०. १०५, ५.
केशिनः १. १६४, ४४; ८. १, २४.
केशिना १. १०, ३; ८२, ६; ३. ६, ६; ४१, ९; ८. १४, १२; १७, २, १०. १०५, २.
केशिनीः १. १४०, ८; १५१, ६.
केशिऽभिः १. १६, ४; ८. १७, ४.
केशी १०. १०२, ६; १३६, १^{५}; ६; ७.
कोकऽयातुं ७. १०४, २२.
कोपयः १. ५४, ४.
कोपयत् १०. ४४, ८.
कोपयथ ५. ५७, ३.
कोम्या १. १७१, ३.
कोशः १. ११२, ११; २. १६, ५; ६. ५४, ३; १०. ८५, ७.
कोशं १. १३५, २; ३. ३२, १५; ४. १७, १६; २०, ६; ५. ५३, ६; ५९, ८; ८३, ८; ८. ७२, ८; ९. १२, ६; २३, ४; ३६, २; ६६, ११; ७६, ५; ८६, १; ३; ७; ८७, १; ९६, २०; १०३, ३; १०७, १२; २६; १०८, ९; १०. ४२, २.
कोशयीः ६. ४७, २२.
कोशाः १. ८७, २.
कोशान् ६. ४७, २३; ९. ८६, २०.
कोशासः ७. १०१, ४; ८. २, ८; ९. ८८, ६.
कोशे ८. २०, ८; २२, ९; ९. ७५, ३; ७७, १; १०. १००, १०.
कोशेन १. १३०, २.
कौ १०. ९०, ११^{२}.
कौरयाणः ८. ३, २१.
कौलिऽतरं ४. ३०, १४.
कौशिक १. १०, ११.
क्रंसते १. १२१, १.
क्रक्षमाणं ८. ७६, ११.
क्रतवः १. ५५, ८; ८९, १; ७. ४८, १; ८. ९६, ३; १०. ६४, २.
क्रतवे १०. २७, १६.
क्रतुः १. १७, ५; ६६, ३; ६७, १; ७७, ३; ९१, ५; १२७, ९; १७५, ५, ३. ११, ६; ५२, ४; ४. २१, २; ५. ३५, १; ७. ३१, ५; ९. १०७, ३; १०. १०४, १०.
क्रतुना १. १४१, ९; २. ५, ४; १२, १, १३, ११; २२, ३; ३. ५४, ६; ७. ९०, ५; ८. ५७, १; ९. ७१, ९, १०. ८, ७; ३१, २; ९१, ३.
क्रतुऽप्राः ४. ३९, २; १०. १००, १२.
क्रतुऽभिः १. ९१, २; १००, १४; १३२, ५; ५. ३२, ५; ३३, ८; ६. ७, ४; ८. ६३, १; ९. ९७, ३०; १०. ८७, १; ९५, ९; १०५, ६.
क्रतुं १. २, ८; १९, २; ४२, ७–९; ६४, १३; ६८, २; ५; ८०, १५; १२३, ८; १३; १५१, २; १५६, ४; २. १६, २; ४; ३०, ६; ३. १, ५; ४५, ३; ४. १०, १; २०, ३; ४०, ४; ४२, १; ५. ३१, ११; ८५, २; ६. ९, ५; १६, ८; ३६, २; ७. ३, १०; ५, ६; ११, ४; ३२, २६; ६०, ६; ८. ७, २४; १२, ११; १३, १; १५, ७; ३३, १७; ४२, ३; ५३, ६; ६२, ७; १०; ६३, ५; ७०, १३; ९. ४, ३; ८६, ४३; १०. ११, ३; २५, १; ४; ३०, १२; ३६, १०; ३७, ५; ४८, ३; ५६, ४; ६४, ७; १२०, ३; १४०, ४; १५९, २.
क्रतुऽमत् २. २३, १५.
क्रतुऽमता १०. ५९, १.
क्रतुऽमंता १. १८३, २.
क्रतुऽमान् १. ६२, १२; ४. ४१, १; ९. ९०, ६; १०. ११३, १.
क्रतुऽयंति ४. २४, ४; १०. ६४, २.
क्रतुऽवित् ९. ४४, ६; ६३; २४; ८६, ४८; १०. २, ५.
क्रतुवित्ऽतमः ९. १०८, १.
क्रतुऽविदं ३. ४०, २.
क्रतुविदा २. ३९, २.
क्रतून् ९. ७२, ५.
क्रतूनां ४. ३१, ५.
क्रतोः ४. १०, २.
क्रतौ १०. ९५, ३.
क्रत्वः ७. ८९, ३; ८. ७८, ७.
क्रत्वा १. ३९, १; ६५, ५; ६९, १; ७३, २; ८१, ४; १२८, ४^{२}; ५; १३८, ३^{२}; १४१, ६; १४३, २; १४५, २; १६५, ७; १९०, ३; ३. २, ३; ६, ५; ९, ६; ४. १, १; ५, ७; १२, १; २१, १०; २८, ३; ३३, ९; ५. १०, २; १७, ४; २९, ५; ७; ८७, २; ६. २, ८; ५, ३; १२, ४; १६, २६; १७, ६; ४८, ४; ६८, ९; ७. ४, ५; २१, ६; २८, २; ६१, २; ६२, १; ७६, १; ८. १९, २९; ३३, ६; ६१, ४; ६६, ४; १०; ८८, ४; ९७, १०; १०२, ८; ९. १६, २; ४; ८६, १३; १०२, ८; १०. २९, ७; ६१, १; ८३, ५; ८४, ६; १४४, ६^{२}.
क्रत्वाऽमघासः ५. ३३, ९.
क्रत्वे १. १११, २; १३५, १; ४. ३७, २; ५. ४३, ५; ६. ४०, २; ७. २५, ४; ९. ३६, ३; १००, ५; १०९, २; १०; १०. ५७, ४.

क्रदुः ९. ९७, १८; २८.
क्रन् ७. ५, ७.
क्रंत १. १४१, ३.
क्रंतः ४. २, १४.
क्रंद २. ४२, ३; ५. ८३, ७.
क्रंदत् १. ३६, ८; १७३, ३.
क्रंदत् १०. ४४, ८; ९५, १३.
क्रंदति १. १००, १३.
क्रंदत्ऽइष्टये १०. १००, २.
क्रंदतु ५. ५८, ६.
क्रदन् ३. २६, ३; ९. ३८, ६; ४२, ४; ९६, २२; ९७, ३३.
क्रंदनुः ७. ४२, १.
क्रंदंति १०. ९४, २.
क्रंदय ६. ४७, ३०.
क्रंदसि १०. ३८, १.
क्रंदसी इति २. १२, ८; ६. २५, ४; १०. १२१, ६.
क्रमणाय ६. ७०, ३.
क्रमणे इति १. १५५, ५.
क्रमते १. १४४, १.
क्रमस्व ४. १८, ११; ८. १, ४; ८१, ७.
क्रमाम ६. ४९, १५.
क्रमिष्ट १. १५५, ४.
क्रमिष्ट ८. ६३, ९.
क्रमिष्टं १. १८२, ३.
क्रमीः १. ५१, ६.
क्रमुः ७. ३२, २७.
क्रवणस्य ५. ४४, ९.
क्रविषः १. १६२, ९; १०.
क्रविषा १०. ८७, १६.
क्रविष्णुः १०. ८७, ५.
क्रव्यऽअत् १०. १६, १०; ८७, ५.
क्रव्यऽअदः १०. ८७, २; १९.
क्रव्यऽअदं १०. १६, ९; १६२, २.
क्रव्यऽअदे ७. १०४, २.
क्रव्यऽवाहनः १०. १६, ११.
क्राणस्य १. १३२, २.
क्राणा १. ५८, ३; १३९, १; ५. ७, ८; १०, २; ९. ८६, १९; १०२, १; १०. ६१, १.
क्राणाः १. १३४, २^{२}; १०. ९२, ६.
क्राणाय १०. १३२, २.
क्राणासः १. १३४, २.
क्राम १०. १६४, १.
क्रामेम १. १०५, ६; ५. ५३, ११.
क्रियते ९. ७०, ८; १०. ११२, ९.
क्रियंते ३. ४१, ३; ८. ९०, ३.
क्रियमाणं ६. ५२, २; ७. ३५, १४.
क्रियमाणस्य १०. ५५, ७.
क्रियमाणा ५. २९, १५.
क्रियाम १०. ३२, ९.
क्रियासु ६. २३, ६.
क्रिविः ५. ४४, ४; ८. ८७, १; ९. ९, ६.
क्रिविःऽदती १. १६६, ६.
क्रिविं १. ३०, १; २. १७, ६; २२, २; ८. २०, २४; २२, १२; ५१, ८.
क्रीणाति ४. २४, १०.
क्रीळति ९. ६६, २९; १०. ३४, ८.
क्रीळथ ५. ६०, ३.
क्रीळन् ५. १९, ५; ९. ८०, ३; ८६, २६; ४४; ९६, २१; १०८, ५; ११०, १०; १०. ७९, ६.
क्रीळंतः ४. ४, ९; ९. २१, ३.
क्रीळंतं ९. ६, ५; ४५, ५; ९७, ९; १०६, ११.
क्रीळंति १. १६६, २; ८. १३, ८.
क्रीळंतौ १०. ८५, १८; ४२.
क्रीळं १. ३७, १; ५.
क्रीळयः १. ८७, ३; १०. ७८, ६; ९४, १४; ९५, ९.
क्रीळुः ९. २०, ७.
क्रीळुमत्ऽभिः १०. ३, ५.
क्रुद्धः १०. ४३, ८.
क्रुद्धं ५. १५, ३.
क्रुध्मी ७. ५६, ८.
क्रुमुः ५. ५३, ९.
क्रुमुं १०. ७५, ६.
क्रोशनासः १०. २७, १८.
क्रोशंतः १०. ९४, ४.
क्रोशंति ४. ३८, ५.
क्रोष्टा १०. २८, ४.
क्रोशं ६. ४६, १४.
क्व १. ३४, ९^{२}; ३५, ७; ३८, २^{२}; ३^{२}; १०५, ४; ५; १६१, ४; १२; १६४, ४; १७; १६५, ६; १६८, ६^{२}; २. ३३, ७; ३. ३०, ३; ६२, १; ४. ५१, ६; ५. ३०, १; ६१, २^{२}; ६. १६, १७; ६३, १; ७. ८८, ५; ८. १, ७^{२}; ७, २०; ६४, ७; १००, १०; १०. ३४, १०; ४०, १४; ५१, २; ८५, १५^{२}; ८६, २२; १११, ८^{२}; १६८, ३.
क्वो३ इति १. ३८, ३.
क्षत्ता ६. १३, २.
क्षत्रं १. २४, ६; ४०, ८; ५४, ८; ११; १३६, १; ३; १५७, २; ६; १६०, ५; १६२, २२; ३. ३८, ५; ४. १७, १; २१, १; ५. २७, ६; ३४, ९; ६२, ६; ६४, ६; ६६, २; ६७, १; ६८, ३; ६. ८, ६; २५, ८; ५०, ३; ६७, ५; ६; ७. १८, २५; ३४, ११; ६६, ११; ८. २५, ८; ३५, १७; १०. १८०, ३.
क्षत्रऽश्रियं १. २५, ५.
क्षत्रऽश्रीः ६. २६, ८.
क्षत्रस्य ५. ४४, १०.
क्षत्रा १०. ६०, ५.
क्षत्राणि ४. ४, ८; ८. १९, ३३; ३७, ७.
क्षत्राय १. ११३, ६; ३. ३८, ३; ७. २१, ७; २८, ३; ३०, १; ८. २२, ७; ३७, ६; १०. १८, ९.
क्षत्रियं ७. १०४, १३.
क्षत्रियस्य ४. १२, ३; ४२, १; ५. ६९, १; १०. १०९, ३.
क्षत्रिया ८. २५, ८.
क्षत्रिया ७. ६४, २.
क्षत्रियाः १०. ६६, ८.
क्षत्रियान् ८. ६७, १.
क्षदसे १. २५, १७.
क्षमाऽइव १. १३०, ४; १०. १०६, ७.
क्षन् १०. ९५, १५.
क्षपः १. ४४, ८; ६४, ८; ११६, ४; २. २, २; ६. ५२, १५; ७. १५, ८; ८. ४१, ३; १०. ७७, २.

क्षपः १. ७०, ४; ७९, ६; ४. १६, १९; ८. १९, ३१; २६, ३.
क्षपा ९. ९९, २.
क्षपाभिः ४. ५३, ७.
क्षपां ३. ४९, ४.
क्षपाऽवान् ३. ५५, १७; ७. १०, ५; ८. ७१, २.
क्षपाऽवान् १. ७०, ३; १०. २९, १.
क्षमध्वं २. २९, २.
क्षमध्वं २. २८, ३.
क्षममाणं १०. १०४, ६.
क्षमा १. १०३, १; ५. ५२, ३; ८. २०, २६; १०. ५९, ८; ९.
क्षमि १. २५, १८; ३. ८, ७; ४. ३०, १२; ७. २७, ३; ८. ४३, ६; ४५, ३२; ६०, ७; १०. १०, १; ६५, ११.
क्षमेत २. ३३, १.
क्षम्यस्य २. १४, ११; ७. ४६, २.
क्षयः १. १४४, ७; ३. ८, १; ५. १२, ६; ७. ६६, ५; ८. १५, ९; ६३, ७; ६४, ४.
क्षयत् ६. २३, १०; ७. २०, ६.
क्षयत् ८. ६९, ११; १०. १०६, ७.
क्षयतः ६. ५१, ४.
क्षयतः १०. ६५, ८.
क्षयति ५. ४२, ११.
क्षयति १. ३२, १५; ५१, १४; १०. १२०, ८.
क्षयत्ऽवीर १. ११४, १०.
क्षयत्ऽवीरः ८. १९, १०.
क्षयत्ऽवीरं १. १०६, ४; १२५, ३.
क्षयत्ऽवीरस्य १. ११४, ३.
क्षयत्ऽवीराय १. ११४, १; २; १०. ९२, ९.
क्षयथ ६. ५१, ७; १०. ३०, १२.
क्षयथः ९. ९५, ५.
क्षयथः १. ११२, ३.
क्षयन् १. २४, १४; ३. २५, ३.
क्षयंतं ७. १००, ५; ८. १९, ३५; १०. १४०, ५.
क्षयंता ७. ६४, १.
क्षयंतीः १०. ९, ५.
क्षयंतौ ७. ९३, २.
क्षयं १. ४०, ७; १३२, ३[२]; १३३, ७; २. ११, १४; ३. २, ६; १३; ३, २; ११, ७; ४०, ४; ४. ५३, ७; ५. ४८, ४; ६. २, ५; ४९, १५; ७. १, १२; ५९, २; ८. ४७, ४; ९. ८२, ३; ९७, २६; १०. ४७, ८; ६३, ५.
क्षयय ३. ४६, २.
क्षयसि ४. ५, ११; ६. १३, २; १०. ९१, ३.
क्षयस्य ४. २०, ८; ५. ९, २; ६. ७१, ६; ८. ६१, १४.
क्षयान् ४. ५४, ५.
क्षयाम १. १११, २.
क्षयाय १. ३६, ८; १२३, १; ४. ५३, ६; ५. ६५, ४; ६. ५०, ३; ७. ६०, ११; ८. १५, १३; ६८, १२; ९. ९, २; १०९, ३; १०. ९, ३; ५८, १; ९९, ८.
क्षये १. ७४, ४; ८६, १; ५. ६४, ४; ५; ६. २५, ६; ८. २, ७; १०. २२, १; ११८, १.
क्षयेण ७. ४६, २.
क्षयेषु ५. २३, ४; ८. ८४, ८; १०. ८, २.
क्षयौ २. २७, १५.
क्षरं ९. ३५, ३; ६१, ३.
क्षर ९. ६, २; १७, ८.
क्षरत् ९. १०९, ८.
क्षरत् ९. ८६, २०.
क्षरति १. १६४, ४२; ५. ५९, २; ८. १३, ४.
क्षरध्यै १. ६३, ८.
क्षरन् १. ११६, ९.
क्षरंतः २. ११, १; ९. ४६, १.
क्षरंति ८. ४९, ६.
क्षरंति १. ७२, १०; ९०, ६; १२५, ४; १६४, ४२; ५. ६२, ४; ६६, ५; ८. ५०, ४; १०. १३, ५.
क्षरंती १. १८१, ७.
क्षरंतीः ७. ३४, २.
क्षरंतीं ४. १९, ६.
क्षरंतु ९. ८६, ३७.
क्षरसि १. २७, ६.
क्षाः १. १३३, ६; ४. १७, १; २२, ४; २८, ५; १०. २, ६; २२, १४; ३१, ५.
क्षातिः ६. ६, ५.
क्षां १. ६७, ३; ९५, १०; ९६, ७; १५८, ४; १७४, ७; १८३, २; १८९, ३; २. २०, ७; ३. ३२, ११; ६. ६, ४; १७, ७; १८, १३; २२, ८; ७. १८, १६; ९. ७१, ९; १०. ३१, ९; ७४, २.
क्षाम ४. २, १६; १९, ४; ६. ५१, ११; १०. ४५, ४; १७६, १.
क्षामऽइव २. ३९, ७; ६. ५, २; १०. १०६, १०.
क्षामः ८. ७०, ४.
क्षामणि ९. ८५, ११.
क्षामन् ६. १५, ५.
क्षामा १०. १२, १.
क्षासु १. १२७, १०; ५. ६४, २.
क्षिणंति ६. ७५, ७.
क्षिणाति १०. २७, १३.
क्षिणां १०. २७, ४.
क्षितऽआयुः १०. १६१, २.
क्षितः ८. २५, ५.
क्षितयः १. ३३, ६; १००, ७; १५१, ३; ३. १८, १; ४. २४, ४; ३८, ५; ५. १, १०; ३२, १०; ३६, ६; ६. १, ५; ७. २८, ४; ८. १६, ९; ९. ८९, ६.
क्षितिः १. ६५, ३; १५१, ४; ४. ५, १५.
क्षितिऽभ्यः ३. १३, ४; ६. ६१, ३; १०. ८९, ११.
क्षितिषु १. ७३, ४; २. २, ३; ७. ८८, ७.
क्षितीः ३. ३, ९; १४, ४; ५. ३७, ४; ६. ६५, १; ७. ६५, २; ७५, ४; ७९, १; ८. ६, २६.
क्षितीनां १. ७, ९; ५९, १; ७२, ७; १७६, ३; १७७, ३; ३. २०, ४; ३४, २; ५. ७, १; ३५, २; ६. ३२, ४; ४६, ७; ७. ९८, १; ८. ६७, १३; १०. ७८, १; १८७, १.

क्षिप् २. ३०, ५.
क्षिपः ३. २३, ३; ५. ४३, ४; ९. ८, ४; १४, ७; १५, ८; ४६, ६; ६१, ७; ७९, ४; ८०, ४; ५; ८५, ७; ८६, २७; ९७, १२.
क्षिपणिं ४. ४०, ४.
क्षिपणोः ४. ५८, ६.
क्षिपत् ४. २७, ३; १०. १८२, १.
क्षिपाभिः ९. ९७, ५७.
क्षिप्ता १. १२९, ८.
क्षिप्रऽइषवे ७. ४६, १.
क्षिप्रऽधन्वा ९. ९०, ३.
क्षिप्राऽइव ४. ८, ८.
क्षिप्रेण २. २४, ८.
क्षियतः १. १२६, १.
क्षियंतः ४. २५, ८; ७. ८८, ७; ८. ८३, ६.
क्षियंतं १. ११७, ५; २. ११, ५; १२, ११; ३. ३०, ८; ३९, ५; ४. १७, १३; १०. ६८, ८.
क्षियंति ७. ७४, ६; १०. ५१, २; १२५, ४.
क्षीयते २. ९, ५.
क्षीयंते १. ६२, १२.
क्षीयंते ६. ४५, ३.
क्षीरऽपाकं ८. ७७, १०.
क्षीरं १. १६४, ७; ९. ६७, ३२; १०. ८७, १६.
क्षीरेण १. १०४, ३.
क्षीरैः ८. २, ९.
क्षु १०. ६१, १२.
क्षुद्रंऽइव १. १२९, ६.
क्षुद्राऽइव ८. ४९, ४.
क्षुधः ८. ६६, १४; १०. ४३, ३.
क्षुधं ८. ६०, २०; १०. ४२, १०; ११७, १.
क्षुधे ७. १, १९.
क्षुध्यत्ऽभ्यः १. १०४, ७.
क्षुभा ५. ४१, १३.
क्षुऽमत् ९. ८६, १८.
क्षुऽमतः २. १, १०; १०. ११६, २.
क्षुऽमति ४. २, १८.
क्षुऽमतीं १०. ११, ३.
क्षुऽमतीः १०. २, ६.
क्षुऽमंतः १. ३०, १३; १०. ३१, ५.
क्षुऽमंतं २. ४, ८; ९, ५; ८. ८१, १; ८८, २; १०. ३८, २.
क्षुंपंऽइव १. ८४, ८.
क्षुरं ८. ४, १६; १०. २८, ९.
क्षुराः १. १६६, १०.
क्षे ४. ३, ६.
क्षेति ३. ५५, ४; ७; ५. ३७, ४; ७. ३२, ९; ८. ८४, ९; १०. ४०, ११.
क्षेति १. ६४, १३; ८३, ३; ९३, २; २. २७, १३; ३. ५५, २१; ४. १, ९; ५०, ८; ५. ६१, १९; ८. ३९, ९; ९. १२, ३; ७२, ३; १०. ९१, २; १२४, ८; १३६, ५.
क्षेत्रऽजेषे १. ३३, १५.
क्षेत्रे १. १००, १८; ३. ३१, १५; ५. ४५, ९; ६. ४७, २०; ९. ८५, ४; ९१, ६; १०. ३३, ६.
क्षेत्रेऽइव १. ११०, ५.
क्षेत्रऽवित् ४. ७०, ९.
क्षेत्रवित्ऽतरः १०. २५, ८.
क्षेत्रऽविदं १०. ३२, ७.
क्षेत्रऽविदा १०. ३२, ७.
क्षेत्रऽसाता ७. १९, ३.
क्षेत्रऽसाधसं ८. ३१, १४.
क्षेत्रऽसाधसः ३. ८, ७.
क्षेत्रऽसां ४. ३८, १.
क्षेत्रस्य १. ११२, २२; ४. ५७, १–३; ७. ३५, १०; १०. ६६, १३.
क्षेत्राणि ६. ६१, १४.
क्षेत्रात् १. ११९, ७; ५. २, ३; ४.
क्षेत्राय ७. १००, ४.
क्षेत्रे ५. ६२, ७.
क्षेपयत् ५. ९, ७.
क्षेमाः १०. ५१, ६.
क्षेमः १. ६७, १; १०. २०, ६.
क्षेमऽकामासः १०. ९४, १२.
क्षेमं १. ६६, २; १०. १२४, ७.
क्षेमऽयंतः ४. ३३, १०; ५. ४७, ४.
क्षेमऽयंतं ३. ७, २.
क्षेमस्य १. १००, ७; ७. ८२, ४; ८. ३७, ५.
क्षेमासः ८. १९, ८.
क्षेमे ५. ३७, ५; ७. ५४, ३; ८६, ८; १०. २७, ४; ८९, १०.
क्षेमेण १. ५५, ४; ७. ८२, ५.
क्षेमेभिः ८. ८४, ९.
क्षेम्या १०. २८, ५.
क्षेपत् ६. ३, १.
क्षेपि ७. १८, २.
क्षेषि ६. ४, ४; १०. ५१, ५.
क्षेष्यंतः २. ४, ३.
क्षैतः ९. ९७, ३.
क्षैतऽवत् ६. २, १.
क्षैत्रऽपत्येषु १. ११२, १३.
क्षैत्राय ८. ७१, १२.
क्षोः ९. ९७, २२.
क्षोणयः १०. २२, ९.
क्षोणस्य १. ११७, ८.
क्षोणी इति १. १८०, ५; ८. ७, २२; ५२, १०; ९९, ६.
क्षोणीः १. ५४, १; १७३, ७; ८. ३, १०; १३, १७.
क्षोणीःऽइव १. ५७, ४.
क्षोणीभिः २. ३४, १३; १०. ९५, ९.
क्षोणीभ्यां २. १६, ३.
क्षोदः १. ६५, ३^{२}; ६६, ५; ९२, १२; १८०, ४; २. २५, ३; ६. १७, १२; ८. २५, १५; १०. ५६, ७; ६१, २.
क्षोदंति ७. ५८, १.
क्षोदते ५. ५८, ६.
क्षोदसः १. १८२, ५.
क्षोदसा १. ११२, १२; ५. ५३, ७; ७. ९५, १.
क्षोभणः १०. १०३, १.
क्ष्णोत्रेणऽइव २. ३९, ७.
क्ष्णौमि १०. २३, २.
क्ष्मः १. १००, १५.
क्ष्मया १. ५५, ६; ५. ८४, ३; ७. ४६, ३; १०. ६१, ७; ८९, ३.
क्ष्विंकाः १०. ८७, ७.

ख

खजऽकृत् ६. १८, २; ७. २०, ३; ८. १, ७.

खजंऽकरः १. १०२, ६.
खदिरस्य ३. ५३, १९.
खनमानः १. १७९, ६.
खनामि १०. ९७, २०.
खनामि १०. १४५, १.
खनिता १०. ९७, २०.
खनित्रिमाः ७. ४९, २.
खनित्रैः १. १७९, ६.
खं ४. ११, २; १०. १५६, ३.
खरऽज्रुः १०. १०६, ७.
खरमज्रा १०. १०६, ७.
खर्गलाऽइव ७. १०४, १७.
खलु १०. ३४, १४.
खले १०. ४८, ७.
खाताः ४. ५०, ३.
खादःऽअर्णाः ५. ४५, २.
खादति १. १५८, ४.
खादथ १. ६४, ७.
खादयः १. १६६, ९; ५. ५४, ११; ७. ५६, १३.
खादिः १. १६८, ३.
खादिनः २. ३४, २.
खादिनं ६. १६, ४०.
खादिषु ५. ५३, ४; १०. ३८, १.
खादिऽहस्तं ५. ५८, २.
खानि २. १५, ३; ४. २८, १; ५. ३२, १; ७. ८२, ३.
खां २. २८, ५; ६. ३६, ४.
खायः ४. ३२, १७.
खिदत् ४. २८, २.
खिदति ४. २५, ७.
खिद्रं ५. ८४, १.
खिद्वः ६. २२, ४.
खिल्याः १०. १४२, ३.
खिल्ये ६. २८, २.
खुदते १०. १०१, १२.
खृगलाऽइव २. ३९, ४.
खे ८. ७७, ३; ९१, ७[२].
खेदया ८. ७२, ८; ७७, ३.
खेदां १०. ११६, ४.
खेलस्य १. ११६, १५.
ख्यः ६. १५, १५.
ख्युः १. ४, ३; ६. ४८, १९; ८. ६५, ९.
ख्यत् १०. ५३, २.
ख्यत् ७. ३६, ७; ८. ७९, २.
ख्यतं ८. ४७, ११.
ख्यतं ५. ६५, ६; ८. २२, १४; ७३, १५.
ख्यन् ३. ३१, १२.
ख्यन् १. १६२, १; ७. ९३, ८; १०. १०, २.
ख्यं ७. ८६, २.

ग

गंगे १०. ७५, ५.
गच्छ ६. ७५, १६.
गच्छ १०. १६, ३[२]; ८५, २६; १५५, १; ३.
गच्छत १०. १५, ११.
गच्छतं १. ३४, १०; ५. ७५, ३; ८. ८, १; ८५, १; ६.
गच्छतं १. ३४, ७; ४७, ३; १३५, ७[२]; ४. ४६, ५; ४९, ३; ५. ७५, ७; ६. ६०, ९; १४; ८. ३५, ४; १०; ७३, १४.
गच्छतात् १०. १५४, १; ५.
गच्छतां १. २१, ४; २२, १; १०. १६, ५.
गच्छति ९. ९८, ७; १०. ८६, १२.
गच्छति १. १, ४; १६, ८; १८, ८; ४१, ६; ८३, १; १२५, ५; २. २५, ४; ८. ६४, ८; ९. ७, ७; १५, ६; ८६, १२; १०. १४, १३; ८६, १०.
गच्छतु ९. ६३, २२; ९७, ६; १०. १६, ३; ९.
गच्छते ९. ९३, २.
गच्छथ ५. ५५, ७.
गच्छथ १. १६१, ११; ६. ५२, ८.
गच्छथः १. २२, ४; ११२, १८; ११७, २; १५१, ७; ४. ४३, ३; ७. ६९, २; ७४, १; ८२, ७; ८. ९, ६; १०. ४१, २; ३.
गच्छथः ४. ४५, ४; ५. ७४, ३; ८. ३५, ७; १३; १०. ४०, ३[२].
गच्छध्वं १०. १९१, २.
गच्छन् ४. ३८, ४; ५. ४५, ९; ९. १५, १; २५, ५; ३८, १; ४; ६१, २५; ९०, १.
गच्छंतः ९. ८, २; ६३, ६.
गच्छंति १. १४५, ४.
गच्छंति १. ८५, ११; १४५, ३; १०. ११७, १; १६८, २.
गच्छंतु ९. ८१, ४; १०१, ४.
गच्छसि ४. ३१, ५.
गच्छसि ८. ९३, ६; ९. २०, ७; ६७, १९.
गच्छस्व १०. १४, ८[२].
गच्छाः ६. ३५, ३.
गच्छात् १०. १०८, ३.
गच्छाति १०. १६, २.
गच्छाति ७. ३३, १४.
गच्छाथ ८. ७, ३०.
गच्छान् ८. ७९, ५.
गच्छान् १०. १०, १०.
गणः १. ८७, ४[२]; ३. ३५, ९; ५. ६१, १३; ७. ५६, ७; १०. १३७, ५.
गणऽपतिं २. २३, १.
गणऽपते ६०. ११२, ९.
गणं १. १४, ३; ३८, १५; ६४, १२; ४. ३५, ३; ५. ४४, १२; ५२, १३; १४; ५३, १०; ५६, १; ५८, १; २; ६. ५६, ५; ८. ९४, १२; ९. ३२, ३; १०. ३६, ७; ७७, १.
गणंऽगणं ३. २६, ६; ५. ५३, ११.
गणश्रिऽभिः ५. ६०, ८.
गणऽश्रियः ८. २३, ४.
गणऽश्रियः १. ६४, ९.
गणस्य ५. १, ३; १०. ३४, १२.
गणाः ५. ७९, ५.
गणानां २. २३, १.
गणाय ७. ५८, १.
गणे ६. ४०, १; ८. ४६, ३१.
गणेन १. २३, ७; ११७, ३; ३. ३२, २; ४. ५०, ५; ७. ९, ५; ९. ९६, १७; १०. १०३, ३.
गणेषु १०. ११२, ९.
गणैः १. ६, ८.
गण्यां ३. ७, ५.
गत १. ३, ७; १०६, २; २. ४१,

१३; ५. ५१, २; ७. ५९, १०; ८. २०, २; १०; ९. ५, ११; १०. १५, ४; ७७, ४.
गतऽअंसुं १०. १८, ८.
गतः ७. ५८, ३.
गतं १. १०५, ४; ११९, ४; २. ३७, ५.
गतं १. २, ४; ४६, १३; ४७, ७; ९; ११२, १–२३; १३५, ४[२]; ३. १२, १; ५८, ४; ९; ४. ४६, ५; ५. ५, ७; ७१, ३; ७३, १; ७४, ६; ६. ५९, १०; ६०, ८; १५; ७. ७०, १; ७३, ४; ८२, ८; ८३, ३; ९४, ७; ८. ५, १३; १६; ३०; ८, ६; १०, ५; २२, ५; १०; १२; २६, ८; ९; ३८, ४; ७; ७३, १०; ८७, १; ६; १०. ६१, ४.
गतिं ५. ६४, ३.
गत्वार्य ८. १००, ८.
गत्वी ४. ४१, ५.
गथ ८. २०, १६.
गधि ८. ९८, ४.
गध्यं ४. १६, ११; १६.
गध्यस्य ६. १०, ६; २६, २.
गध्या ४. ३८, ४.
गन् ७. ५०, १.
गनिग्मतं १०. ४१, १.
गनीगंति ६. ७५, ३.
गंत १. ३८, २; ३९, ७; ९; ५. ८७, ९; ८. २७, ५.
गंत ६. ४९, ११.
गंत १. ३, ८; ५. ४३, १०; ८. २०, १.
गंतन २. ३६, ३; ८. ५४, ३.
गंतन २. ३४, ५; ६; ५. ५७, १; ७. ४३, ४; ५९, ५; ८. ७, ११; २७.
गंतं ५. ४३, ८; ८. ८७, ४.
गंतं १. १३५, ५; १३७, १; ३; १५१, ७; २. ३९, ३; ५. ७१, १; ६. ६३, २; ७. ६८, २; ८. ८, ७; १७; ९, १.
गंतवे १. ४६, ७.
गंतवै १०. ९५, १४.
गंता १. ८६, ३; २. २३, १३; ४१, २; ४. २९, ४; ५. ३०, १; ६. २३, ४; ४४, १५; ८. ७१, ५.
गंतारः ३. २६, ६.
गंतारं १. ९, ९.
गंतारा १. १७, २; ८. ५, ५; १३, १०; २२, ३.
गंतु १. १७५, २; १८६, ६; ५. ४३, ८; ११; १३; ७. १८, ४; ८. ६३, ४.
गंतोः १. ८९, ९; ३. ५४, १८.
गंधः १. १६२, १०.
गंधर्वः १. १६३, २; ९. ८३, ४; ८५, १२; १०. १०, ४; ८५, ४०; ४१; १२३, ४; १३९, ५; ६; १७७, २.
गंधर्वे ८. १, ११; ७७, ५; ९. ८६, ३६; १०. १३९, ४.
गंधर्वस्य १. २२, १४.
गंधर्वाः ९. ११३, ३.
गंधर्वाणां १०. १३६, ६.
गंधर्वान् ३. ३८, ६.
गंधर्वाय १०. ८५, ४१.
गंधर्वीः १०. ११, २.
गंधारीणांऽइव १. १२६, ७.
गन्म २. २८, ७; ६. ६१, १४.
गन्वहि ८. ६९, ७.
गभस्तिऽपूतः ९. ८६, ३४.
गभस्तिऽपूतं २. १४, ८.
गभस्तिं १. ५४, ४.
गभस्ती इति ६. १९, ३; ७. ३७, ३.
गभस्तौ १. ६२, १२; २. १८, ८; ६. २०, ९; १०. ४४, २; ६१, ३; ७३, ८.
गभस्त्योः १. ६४, १०; ८२, ६; ८८, ६; १३०, ४; ३. ६०, ५; ५. ५४, ११; ८६, ३; ६. २९, २; ४५, १८; ८. १२, ७; ९. १०, २; १३, ७; २०, ६; ३६, ४; ६४, ५; ६५, ६; ७१, ३; ७६, २; १०७, १३; ११०, ५; १०. ९६, ३.
गभीरः ३. ३२, १६; ७. ३३, ८.
गभीरं १. ९१, ३; १०८, २; ३. ४६, ४; ४. ५, ५; ६; ५. ८५, १; १०. ४७, ३; १२९, १.
गभीरऽवेपाः १. ३५, ७.
गभीरा १. २४, ९; ७. ३२, ६.
गभीराः २. २७, ३; ६. ७५, ९; ८. १६, ४; १०. १०८, ४.
गभीरे ८. ६७, ११.
गभीरे इति १०. १७८, २.
गभीरे इति ४. २३, १०; ४२, ३; ५६, ३.
गमः ८. ३, १४; ३३, २; ८; १०. १६, १५.
गमत् १. ५, ३; १७८, २; ३. १३, १; ६. ४५, २४; ७. ३२, १०; ११; ९७, १; ८. १, २७; ४०, २[२]; ९. ४०, २.
गमत् १. १, ५; ३०, ८; ३. १०, ४; ४. ५५, १०; ५. ३६, १; ४६, ५; ६; ८. १, २७; २, २६; १८, ७; ३३, ९; ६१, १; ७२, १; १०२, ९.
गमतः ७. ७३, ४.
गमथः ४. ४३, ४.
गमध्यै १. १५४, ६.
गमन् १०. ४४, ५.
गमन् १. ८९, ७; ८. ५४, ३; ९. ५, ८; १०. १०८, ८.
गमति ७. ३४, २०.
गमंतु ४. ३५, १.
गमंतु १. १०७, २; १८६, २; ६. ४९, १; १०. १५, ५; ३५, १३.
गमं ७. ८९, १.
गमय ५. ५, १०; १०. १५२, ४.
गमयामसि १०. १४५, ४.
गमानि ४. १८, २; ३.
गमाम ८. ९२, २७; १०. ९, ३.
गमिष्ठः १०. १०६, ३; ४.
गमिष्ठा १. ११८, ३; ५. ७६, २.
गमेम ८. ४५, १०; ४६, ९; ५१, ५.
गमेम ४. ५, १३; ५. ४२, १८; ७. ६७, ६; ८४, ५; १०. ४०, ११.
गमेमहि ५. ५१, १५; ६. ५४, २; ७. ८१, २.

गमेयं १. १५८, ३.
गंभरेषु १०. १०६, ९.
गंभीरः २. २१, ४.
गंभीरऽचेतसा ८. ८, २.
गंभीरया ६. १८, १०.
गंभीरऽवेपसः १०. ६२, ५.
गंभीरऽशंसः ७. ८७, ६.
गंभीरान् ३. ४५, ३.
गंभीराय ६. ६२, ९.
गंभीरे ६. २४, ८.
गंभीरेण ६. २४, ९.
गम्याः १. १६३, १३.
गम्याः १. १८१, ३; ५; १८६, ६; १८७, ७; ५. ४१, १८; १०. ३, ७.
गयः ६. २, ८; १०. ६४, १६.
गयं १. ७४, २; ५. १०, ३; ४४, ७; ६. ७१, ३; ७४, २; ७. १८, १३; ३२, ७; ८. २४, २२; ४५, १३; ९. २३, ३; ८१, ३; १०. ६६, ३; ९९, ५.
गयऽसाधनं ९. १०४, २.
गयऽस्फानः १. ९१, १२; १९; ७. ५४, २.
गयस्य ७. १९, १.
गये ८. ४१, ७.
गयेन १०. ६३, १७.
गरन् १. १५८, ५.
गरुत्मान् १. १६४, ४६; १०. १४९, ३.
गर्गरः ८. ६९, ९.
गर्तऽआरुगिव १. १२४, ७.
गर्तं ५. ६२, ८; ६८, ५; ७. ६४, ४.
गर्तऽसत् २. ३३, ११.
गर्ते ५. ६२, ५; ६. २०, ९.
गर्दभं १. २९, ५; ३. ५३, २३.
गर्दभानां ८. ५६, ३.
गर्भ ९. ८२, ४.
गर्भः १. ७०, २[४]; ९५, ४; १५२, ३; १६४, ९; २. १, १४; १०, ३; ३. १, १२; ५, ३; २९, ११; ३१, ३; ५. २, २; ४५, ३; ७८, ७; ६. १५, १; ४७, २८; ७. ९, ३; ८. १२, ११; ९. ६८, ५; ९७, ४१; १०. १, २; ८, २; २७, १४; ३०, ८; ४५, ६; ७९, ४; १६८, ४.
गर्भःऽइव ३. २९, २.
गर्भऽत्वं १. ६, ४.
गर्भऽधिं १. ३०, ४.
गर्भं १. ९५, २; १३०, ३; १५६, ३; १५७, ५; १६४, ३३; ५२; १७३, ३; १८५, २; २. १८, २; ३५, १३; ३. १, ६; १०; १३; २, १०; २७, ९; ३१, २; ७; ४६, ५; ५७, ३; ४. ७, ९; १९, ५; ५. ४१, १०; ४७, ४; ५८, ७; ८३, १; ७; ६. ४८, ५; ५२, १६; ६६, ३; ६७, ४; ७. ४, ५; १०१, १; १०२, २; ८. ६, २०; ९. १९, ५; ७४, ५; ७७, ४; ८३, ३; १०२, ६; १०. २१, ८; २७, १६; ४६, ५; ६८, ७; ८२, ५; ९१, ६; १२१, ७; १६२, १; १८३, ३; १८४, १; २[३]; ३.
गर्भऽरसा १. १६४, ८.
गर्भाः १०. ७३, २.
गर्भिणीषु ३. २९, २.
गर्भे १. ६५, १०; १४८, ५; ४. २७, १; ६. १६, ३५; ८. ४३, ९; ८३, ८; १०. १०, ५; ५३, ११; १७७, २.
गर्भेभ्यः १. १४६, ५.
गर्हसे ४. ३, ५.
गल्दया ८. १, २०.
गवयस्य ४. २१, ८.
गवां ५. ३०, ७.
गवां १. १०, ७; ३१, १२; ३३, १; ८१, ७; ९३, २; १०१, ४; १२२, ७; १२४, ५; ११; १६४, ३; २. २३, १८; ३. ३१, ४; ४. १, १९; ३२, १८; ५१, ८; ५२, २; ३; ५; ५. ३०, ४; ११–१३; ४५, २; ५६, ५; ८६, ३; ६. ६५, ५; ७२, ४; ७. ७६, ६; ७७, २; ९८, ६; १०२, २; १०; १०४, १०; ८. ४, २०; ३६, ५; ४६, २२; ५१, २; ६१, ६; ९. ६५, १७; ६६, २९; ७२, ४; ७७, ४; ८१, १; १०. ४८, ९; ४९, १०; ८७, १८; १०२, ५; ९; १०८, ३; ९; १६६, १.
गवांऽइव १. १३०, ३; ५. ५९, ३; ६. २४, ४.
गवि १. ११९, ६; ४. ५८, ४; ६. ४६, १४; ५६, ३; १०. ९४, ९; १०६, १०; ११६, ४.
गविष्ठिरः ५. १, १२.
गविष्ठिरं १०. १५०, ५.
गवे १. ४३, २; ६; ६. ४५, २२; ८. ५, २०; ३०, ४; ४७, १२; ६८, १३; ९२, २५; ९. ११, ३; ७; ६१, १५.
गव्यता ३. ३१, ९; ४. १, १५; ६. ४६, १०.
गव्यते ६. ४५, २६.
गव्यन् ३. ३३, ११; ९. ८७, ७; ९६, १.
गव्यंतः १. ३३, १; ४. १७, १६; ७. ३२, २३; ८३, १; १०. १६०, ५.
गव्यंते ८. २, ३५.
गव्यंता १. १३१, ३.
गव्यं १. ७२, ८; १२६, ३; १४०, १३; ३. ३२, १६; ४. २, १७; ५८, १०; ५. २९, १२; ३४, ८; ५२, १७; ६१, ५; ६. १७, १; ७. ९०, ४; ९२, ३; ८. २१, १०; ९. १०८, ६.
गव्ययं १०. ४८, ४.
गव्युऽया ८. ९३, १७.
गव्ययीं ९. ७०, ७.
गव्युऽयुः ९. ३६, ६; ९८, ३.
गव्यवः १. १५१, १; ३. ३३, १२; ७. १८, १४.
गव्यस्य १. १३१, ३; ५. ३०, १५; ८. ६६, ३.
गव्यां ६. ४४, १२; ७. ६७, ९.
गव्या ५. ७९, ७; ७. १८, ७; ८. १, १७; ९. १४, ६; ६४, ४; ८७, ५.
गव्यानि ८. ३४, १४; ९. ८, ६; २२, ७; ६२, २३.
गव्युः १. ५१, १४; ३. ३१, ८; ४. २३, १०; ३१, १४; ६. ४१, २; ७. ३१, ३; ८. ५३, ८; ७८, ९; ९. २७, ४; ९७, १५.

गव्यूतिः ९. ७४, ३; १०. १४, २; ८०, ६.

गव्यूतिं ३. ६२, १६; ५. ६६, ३; ७. ६२, ५; ६५, ४; ७७, ४; ८. ५, ६; ९. ७८, ५; ८५, ८.

गव्यूतीः १. २५, १६.

गव्ये ८. १३, २२; ९. १०१, १६.

गव्येभिः ६. ६०, १४; ८. ७३, १४.

गव्यो इति ८. ४६, १०.

गर्हनं १. १३२, ६; १०. १२९, १.

गहि १. ४, २; ३; ६, ९; १४, २; १६, ४; ५; १९, १–९; २३, १; २३; ३०, २२; ४९, १; ८४, १; १३९, ६[२]; १४२, १३[२]; २. ६, ६; ४१, १; २; ३. १, १९; ३७, ११[२]; ४२, २; ४४, १; ४. ३२, १; ५; ५. ५, ९; २६, ४; ५१, १; ३; ६. २२, ११; ४१, १; ५४, ७; ७. ३२, १; ८. १, ९; १६; ३, १७; ४, २; ३; १०; १३, १३; १४; १८, ४; २१, ४; २४, ७; २६, २७; ३२, ६; ३४, ६; १२; ४६, ९; ४९, ७; ५०, ७; ६०, ४; ६५, ९; ६६, ८; १२; ८२, ४; ९५, ८; ९७, ५; ९९, १; ९. ६५, ५; ७२, ९; १०. १४, ५; ३८, ५; १५०, १[२]; १६७, २.

गाः १. १०, ८; ३२, १२; ३३, ३; १०; ६१, १०; ६२, २; ३; ८३, ५; ८४, १६; ९१, २२; ९२, २; ९३, ४; १०१, ५; १०३, ५; ११८, २; १२६, ५; १७४, ४; २. १२, ३; १४, ३; १९, ३; २१, ५; २४, ३; १४; ३४, १; ३६, १; ३. ३०, १०; २१; ३१, २१; ३९, ५; ४४, ५; ५०, ३; ४. १, १५; १७, १०; ११; ३२, २२; ५. १४, ४; २९, ३; ४५, ७; ८; ६२, ३; ६. १७, ३; ५; ६; २३, ४; २७, ८; ३५, २; ३९, ५; ४३, ३; ४७, १४; २४; ५४, ५; ६; ६०, २[२]; ७५, २; ७. ३६, १; ८. २, ३९; ३, १९; १४, ८; ६३, ३; ९६, १७; ९. १४, ५; ४२, १; ६४, ३; १३; ७१, ७; ७२, ३; ७८, १; ८२, १; ३; ८६, २६; ८७, ७; ८; ८९, ३; ९०, ४; ९१, ६; ९५, १; ९६, ८; १६; ९७, १३; ३९; १०७, २६; १०८, ६; १०. ८, ८; १९, ६; ४८, २; ६७, ३; ४; ६; ८; ६८, ३–५; १०; ११; ८९, ७; १०२, ८; १५६, २; १६०, ३.

गाः १. ६७, ३; ३. ५३, २; ४. ३, १३; १६, ९; ७. ६२, २; १०. १, २; ५६, ३; १०८, ९.

गाःऽइव ३. ४५, ३; ८. २०, १९; ४१, १; ९. ११२, ३; १०. १२७, ८.

गांग्यः ६. ४५, ३१.

गात् ७. ३, ९.

गात् १. ३८, ५; १०४, ५; १६४, ४; १६७, ५; २. ३३, १४; ३८, ८; ११; ३. ३१, १; ६; २१; ५. ४५, १; २; ७. ६७, ८; ६९, ४; ८. ५, ३९; १०. ५, ६; १८, ४.

गात ८. २, ३८.

गात ८. २०, २२; १०. १९, १; ७८, ८.

गातन ५. ५५, ९.

गातवे ३. ३, १.

गातुः १. १३६, २; ३. ४, ४; ५४, १८; ५. ३२, १०; ९. ९६, १५; १०. २०, ४; ६; ३०, १; ६१, २५.

गातुऽभिः १. १००, ४.

गातुं १. ७१, २; ७२, ९; ८०, ६; ९५, १०; ९६, ४; ११२, १६; १५१, २; ६; १७३, १३; २. २०, ५; २१, ५; ३. १, २; ३१, ९; १५; ४. ४, ६; १८, १०; ५१, १; ५५, ४; ५. ३०, ७; ६५, ४; ८७, ८; ६. ६, १; २२, ५; ३०, ३; ७. १३, ३; ४७, ४; ६३, ५; ८. ४५, ३०; ९. ६९, ७; ८५, ४; ९६, १०; ९७, १८; १०. १४, २; ४९, ९; ७६, ३; ९९, ८; १०४, ८; १२२, २.

गातुऽमत्या ७. ५४, ३.

गातुऽय ८. १६, १२.

गातुऽयन् १. ५२, ८.

गातुयंतिऽइव १. १६९, ५.

गातुऽवित् १. ५१, ३; ३. ६२, १३; ८. ६६, १४; ९. ४६, ५; ६५, १३; ९२, ३.

गातुवित्ऽतमः ८. १०३, १; ९. ४४, ६; १०४, ५; १०६, १०७, ७.

गातुवित्ऽतमाः ८. १९, १६; ९. १०१, १०.

गातुवित्ऽतरा ८. २५, ९.

गातुऽविदे १. १०५, १५.

गात्रा १. १६२, १८; ८. १७, ५.

गात्राणां १. १६२, १९.

गात्राणि १. १६२, २०; ९. ८३, १.

गात्रात् १. १६२, ११.

गात्रैःऽगात्रे ८. ४८, ९.

गाथऽपतिं १. ४३, ४.

गाथं १. १६७, ६; ९. ११, ४.

गाथया ८. ३२, १; ९८, ९; ९. ९९, ४; १०. ८५, ६.

गाथऽश्रवसं ८. २, ३८.

गाथान्यः १. १९०, १.

गाथान्यं ८. ९२, २.

गाथाभिः ८. ७१, १४.

गाथिनः १. ७, १.

गाधं १. ६१, ११; ५. ४७, ७; ६. २४, ८; ४८, ९; ७. ६०, ७; १०. १०६, ९; ११३, १०.

गाधानि ७. १८, ५.

गाधेषु ८. ७०, ८.

गानि ४. १८, ३.

गांधर्वी १०. ८०, ६.

गां १. ३३, १५; ११०, ८; ११६, २२; ११७, २०; १५१, ४; १६१, ७; १०; १६४, ९; ३. ३४, ९; ६०, २; ४. ३३, ४; ३६, ४; ५७, १; ५. ५२, १६; ६. ४५, ७; ४६, २; ६२, ७; ७. ४४, ३; ८. १, २; ४, २१; १४, ३; ७४, १०; ७८, २; ८१, ३; ९७, २; १०१, १५; १६; ९. ९, ९; ९४, ५; १०. ४२,

२; ५९, १०; ६५, ११; ६७, ५; ९७, ४; १०७, ७; ११२, ८; ११९, १; १४६, ४; १५५, ५; १६५, ५.

गां १०. १२८, ४.

गाम १०. ५७, १.

गांऽइंव ८. ६५, ३; १०. ७९, ६.

गार्य १. ३८, १४; ६. १६, २२; ८. २०, १९; ३३, ४.

गाय ६. ४०, १; ४५, २२; ८. ४६, १४.

गार्यत् १. १६७, ६; १७३, १.

गायत १. ४, १०; ५, १; ४; २१, २; ३७, १; ४; ५. ६८, १; ६. ४५, ४; ७. ३१, १; १०२, १; ८. १५, १; ३२, १३; १७; ४५, २१; ८९, १; ९८, १; १०१, ५; १०३, ८; ९. ११, १; १३, २; ६०, १; ६५, ७; ८६, ४४; ९७, ४; १०४, १; १०५, १.

गायति ८. ९२, २५; १०. ७१, ११.

गायत्रं १. २७, ४; ३८, १४; १२०, ६; १६४, २३; २. ४३, १; ८. १, ८; २, १४; ३८, १०; १०. ७१, ११.

गायत्रऽवर्तनिं ८. ३८, ६.

गायत्रऽवेपसं ८. १, १०.

गायत्रऽवेपसे १. १४२, १२.

गायत्रस्यं १. ७९, ७; १६४, २५.

गायत्राः ८. १, ७.

गायत्रिणः १. १०, १.

गायत्री १०. १४, १६; १३०, ४.

गायत्रे १. १६४, २३.

गायत्रेण १. १२, ११; १६४, २४; १८८, ११; ९. ६०, १.

गायत्रेषु १. २१, २.

गायत्रैः ८. १६, ९.

गार्यतः ८. ६१, ८; ६६, १.

गार्यति १. १०, १.

गायसि २. ४३, २; ८. १९, २२.

गायिषे ७. ९६, १.

गार्ये ८. ४६, १७.

गारीत् ५. ४०, ७.

गार्ष्टेयः १०. १११, २.

गार्हऽपत्यानि ६. १५, १९.

गार्हऽपत्याय १०. ८५, २७; ३६.

गार्हऽपत्येन १. १५, १२.

गार्वः १. २३, १८; २५, १६; ३२, ११; ३८, २; ६६, ५; १०[२]; ७१, १; ९०, ८; ९१, १३; ९२, १; ४; ९५, ६; १३५, ८; १५३, ४; १५४, ६; १६३, ८; १६४, ७; १६८, २; १७३, १; १८६, ७; १८७, ११; १९१, ४; २. १२, ७; ३. ३६, ५; ५३, १४; ५६, २; ४. २३, ९; ४१, ८; ४२, १०; ५. ३०, १०; ३३, १०; ४७, ४; ५३, १६; ५६, ४; ६. २८, १; ४; ५[४]; ४०, २; ४१, १; ४५, २८; ६४, ३; ६७, ११; ७. ९, ४; १८, १; १०; २३, ४; ३५, १२; ७५, ७; ७९, २; ८. ४, १८; ९, १९; २०, २१; ४१, ६; ४६, ३०; ४८, ५; ६९,६; ७२, १२; ९२, १२; ९६, ५; ९. १२, २; २४, २; २६, २; ३१, ५; ३२, ५; ३३, ४; ४१, १; ४९, २; ६२, ५; ६६, १२; ६८, १; ७१, ४; ७२, ६; ८४, ५; ९३, ३; ९४, २; ९७, ९; २२, ३४; ३५; ९९, ३; १०१, ८; १०. ४, २; २५, १; २७, ८; ३२, ४; ३४, १३; ६१, २१; ८५, १३; ८९, १४; ९०, १०; ९५, ६; ९७, ८; १०८, ५; ११; १७२, १.

गावः ६. २८, ६; १०. १००, १०.

गार्वःऽइव ८. ४३, १७; १०. १४६, ३; १४९, ४.

गावा ५. २७, १.

गावाऽइव ३. ३३, १.

गावौ ३. ५३, १७; ६. २७, ७; १०. २७, २०; ८५, ११.

गासि ५. २५, १; ८. २७, २.

गासिषत् ८. ८१, ५.

गाहते १. १२७, ४.

गाहते ९. ३, ६; ७, २; ६७, १४; २०; ८६, ८; २६; ४०; ९९, २; ७.

गार्हमानः १०. १०३, ७.

गाहसे ९. ११०, २.

गाहात् ९. ११०, ८.

गाहेमहि २. ७, ३.

गिरः १. ३, २; ५, ८; ६, ६; ९; ९, ४; १०, ९; १२; ११, १; १४, १; २५, १८; २६, ५; ४५, ५; ५३, १; ५७, ४; ५९, ४; ६१, ४; ६४, १; ७७, ४; ७९, १०; ८२, १; ८४, ८; ९३, ९; ११८, १०; १२१, १; १२२, १४; १५१, ७; ८; १७६, २; १७८, ३; १८६, ७; २. ६, १; २७, १; ३५, १; ३९, ७; ३. ३, ३; १०, ६; २०, २; २४, ४; २९, १०; ३१, १३; ३९, ७; ४०, ८; ४२, ३; ५१, १; २; ६; ५२, ३; ४. ३२, १६; ४१, ८; ५. १०, ४; ११, ५; १३, ३; २७, ३; ३९, ४; ५[२]; ४१, १२; १४; ४३, १०; ६१, १७; ६५, १; ६. १६, १६; ३७; ३४, १; ३६, ३; ३८, ३; ४; ४४, ५; ४५, २३; २५; २८; ४७, १४; ५२, ९; ६९, २; ४; ७. ३, ८; ५, ५; १०, ३; १५, ६; १८, २; ३; २२, ५; ३२, ५; ३९, ५; ४५, ४; ४६, १; ६८, १; ९४, २; ९९, ७; ८. २, ३०; ३, ३; १५; ६, ११; ८, २२; १३, ६; ७; १६; १८; ३२, २३; ३३, १३; ३५, ६; ४३, १; ४४, १९; २२; २५; ५२, ८; ५७, ४; ७१, १०; ८४, ३; ६; ७; ८५, ९; ९२, १९; २७; ९५, १; ६; ९६, १०; १०२, १३; १०३, १; ९. २, ७; ६, ९; २०, ५; २५, ५; ३४, ६; ४०, ५; ४३, २; ६१, १४; २३; ६३, १०; ८५, ११; ९६, ७; ११४, २; १०. २०, १०; २९, ३; ५; ३३, ६; ६१, २५; ६४, १२; ६५, १४; ६६, १०; ६९, ३; ८९, ४; ९१, १२; ९६, १; १०४, ७; १४८, ३; १६०, २.

गिरं ३. ६२, ८; ५. १२, १; १५, १; ४२, १३; ७. ५, १; ८. ७, ९; ९५, ५.

गिरयः १. ६१, १४; ६३, १; ६४, ७; ५. ४१, ११; ६. २४, ८; ६६, ११; ८. ७, ३४; १०. ५९, ३.

गिरा १. ३८, १३; ४६, १३; ७८, १; २; ७९, ५; १३९, ९[२]; १५१, १; २. १, ११; २, १; ५; ६, ६; २४, १; ३०, ११; ३. २७, २; ५३, २; ४. ८, १; ५. १७, ३; १८, ३; २०, ३; ४४, १; ५२, १३; ५३, १६; ६८, १; ८७, ३; ६. १५, १; ७; ७. ३२, २०; ३६, ४; ९४, ११; ८. १, १८; २०; ११, ७; १९, १३; २१; २०, १९; २०; २३, २; ९; २६, १५; २७, ५; ३१, १४; ४०, ४; ७; ४१, २; ४६, १४; १७; ६९, ४; १४; ७४, ११; ९३, ९; ९. १०, ४; १४, २; २९, २; ६२, १५; ६७, ९; ७१, ३; ६; ८६, ३९; ४६; १०. २२, १; ६४, ३; ४; १०१, ३; ११८, ३; १३८, २; १४०, ६.

गिराऽगिरा ६. ४८, १.

गिरां १. १०, ३; ३. ३१, १८; ६. २४, १.

गिराऽवृधे ९. २६, ६.

गिरिः १. ३७, ७; ६५, ३; ४. २०, ६; ८. ७, ५; ५०, २; ९८, ४.

गिरिऽक्षिते १. १५४, ३.

गिरिऽजाः ५. ८७, १.

गिरिऽभ्यः १. १०९, ६; ७. ९५, २; ८. ७७, ६.

गिरिऽभ्रजः १०. ६८, १.

गिरिं १. ५६, २; ४. १७, ३; ५. ५४, ५; ५६, ४; ८. ४५, ३०; ६४, ५; ८८, २; १०. ८९, ७; १५५, १.

गिरिषु ९. ८२, ३.

गिरिऽस्थाः १. १५४, २; ९. १८, १; ६२, ४; ९८, ९.

गिरिऽस्थां ३. ४८, २; ५. ४३, ४; ८. ९४, १२; ९. ८५, १०; ९५, ४.

गिरीणां ६. ६१, २; ८. ६, २८; ७, १४; ४६, १८; ९६, २.

गिरीन् १. ३७, १२; ८. १५, २; १०. ४४, ८; १३८, २.

गिरे ६. ६३, १०[२].

गिरेः १. ५६, ३; १३०, ७; १९१, १६; ६. २६, ५; ८. ३२, ४.

गिरेःऽइव ८. ४९, २.

गिरौ ८. ४५, ५.

गिर्वणः ३. ४०, ६.

गिर्वणः १. ५, ७; १०; १०, १२; ११, ६; ४५, २; ५७, ४; ३. ४१, ४; ५१, १०; ४. ३२, ८; ११; ३४, ७; ६. ३२, ४; ४०, ५; ४५, १३; २८; ४६, १०; ८. १, २६; ३, १८; १२, ५; १३, ४; २२; २४, १२; ३२, ७; ४९, ३; ५१, ६; ५२, ८; ६१, १४; ९०, ३; ९३, १०; ९५, १; २; ९८, ७; ९९, २; ९. ६४, १४.

गिर्वणःऽतम ८. ६८, १०.

गिर्वणःऽतमः ६. ४५, २०.

गिर्वणःऽतमा ५. ८६, ४.

गिर्वणसं २. ६, ३; ६. २४, ३; ५०, ६; ८. २, २७.

गिर्वणसे १. ६२, १; ८. ८९, ७.

गिर्वणस्युः १०. १११, १.

गिर्वाहः १. ३०, ५.

गिर्वाहः १. १३९, ६; ६. २४, ६; ८. २, ३०.

गिर्वाहसं ४. ४४, १; ६. २१, २.

गिर्वाहसे १. ६१, ४; ८. ९६, १०.

गीः १. ७७, १; ११७, १; १६५, १५; १६६, १५; १६७, ११; १६८, १०; १७३, १२; १८१, ७; ८; १८३, २; ४; ३. १, २; ७, ५; ४. ४, ८; ५. ४२, १; ४३, ८; ६. २२, ५; ७. ७०, ७; ७३, १; ८४, ५; १०. ४, ७; ७४, ३; ९९, ११.

गीःऽभिः १. ९, ९; २५, ३; ४९, ४; ५१, १; ९१, ११; १२८, ८; १३९, ६; १४३, ४; २. ६, ३; १०, २; ३. ५, २; १२, १; २६, १; ३७, ३; ५१, ४; ५२, ५; ५३, १; १०; ५८, ८; ४. १०, ४; ४९, ५; ५. ६, १०; ८, ४; २०, १; २२, ४; ३६, २; ७२, १; ८३, १; ६. १, १०; २, २; १३, ४; ६; १५, ६; १७, ३; १८, १; २१, २; २२, १; ३७, ५; ४४, १३; ४५, ७; ४९, १; ६; १०; ५९, १०; ६७, १; ७. ६, २; ५३, २; ८०, १; ९३, ४; ९४, ६; ८. २, २७; ८, ८; १५; १९; ११, ६; १५, १; १६, १; २२, ११; २४, ६; ४२, ५; ४३, २८; ४६, ३; १७; ५४, १; ६०, ९; ६५, ३; ६८, १०; ७६, ५; ८८, १; ९६, ६; ९७, ४; १३; १०३, ७; ९. ३५, ५; ४३, १; ३; ९६, १७; १०. ६, ५; ८५, २१; ८८, ५; ९२, १४; ९८, ९; ११८, ९; १३५, ७; १४१, ३.

गीयमानं ८. २, १४; ८१, ५.

गीयमानासः ६. ६९, २.

गीर्णे १०. ८८, २.

गीर्षु ८. ९२, ७.

गुः ७. ९३, ३.

गुः १. ६५, २; १०४, २; १२०, ८; ४. ३७, २; ५. ४५, १; ७. २१, १०. १२, ३.

गुंगुऽभ्यः १०. ४८, ८.

गुंगूः २. ३२, ८.

गुदाभ्यः १०. १६३, ३.

गुपितः १०. ८५, ४.

गुपितं १०. १०९, ३.

गुरस्व ३. ५२, २.

गुरिति गुः ३. ७, ७.

गुरु १. ३९, ३; ७. ५६, १९; ८. ४७, ७; १०. ३७, १२.

गुरुः १. १४७, ४.

गुरुं ४. ५, ६.

गुष्पितं ८. ४०, ६.

गुहः ८. ६, १७.

गुहत्ऽअवद्यं २. १९, ५.

गुहे १. ६७, ३.

गुहमानः ४. १, ११.

गुहा १. ६, ५; २३, १४; ६५, १; ६७, २; ४; १२३, ७; १३०, ३; १४१, ३; १६४, ४५; १६७, ३; २. ४, ९; ११, ५; १२, ४; २४, ६; ३. १, ९^{2}; ७, १०; ५६, २; ४. ५, ८; ९; १२; ७, ६; १८, ५; २१, ७; ५. २, १; ८, ३; ११, ६; १५, ५; ८. ६, ८; ८, २३; १४, ८; ९. ६, ९; १०, ९; ६८, ५; १०२, २; १०. ५, २; २२, १; १०; ३९, ९; ४५, २; ४६, २; ५४, ५; ६१, १३; ६७, ४; ६८, ७; ७१, १; ७९, २; ८५, १६; १००, ७; १२४, २; १८१, २.

गुहा १. ६७, ३.

गुहाऽइव ३. १, १४.

गुह्य १. ८६, १०; २. ११, ५; ३. ५५, १५; ४. ५, १०; ५८, १; ५. ३, २; ३; ९. ८७, ३; ९६, १६; १०. ५५, १; ७९, ३.

गुह्यमानं ४. ५८, ४.

गुह्या ३. ३८, ३; ५. ५, १०; ७. ८७, ४; ८. ४१, ५.

गुह्याः २. ३२, २; ७. १०३, ८.

गुह्यानि १. ७२, ६; ९. ९५, २; १०. ५३, १०.

गुह्या १०. ५३, ३.

गुह्येन १. १६३, ३.

गुह्येषु ३. ५४, ५; १०. ११४, २.

गूढ्वी ७. ८०, २.

गूर्त १. १७३, २.

गूर्तऽतमाः १. १६७, १.

गूर्तऽमनाः ६. ६३, ४.

गूर्तयः १. ५६, २; ८. ५०, ५.

गूर्तये १०. ६१, १५.

गूर्तवचःऽतमः १०. ६१, २.

गूर्तऽवचाः १०. ६१, १.

गूर्तऽवसुः १०. १३२, १.

गूर्तऽश्रवसं १. ६१, ५.

गूर्तऽश्रवाः १. १२२, १०.

गूर्ताः ४. १९, ८.

गूर्तिऽभिः ९. १०५, १.

गूर्धय ८. १९, १.

गूळ्हं १. ११७, ४; २. ११, ५; ५. ४०, ६; ७. ७६, ४; १०. ७२, ७; १२९, ३.

गूळ्हा ६. ४८, १५.

गूळ्हे इति ८. ९६, १६.

गूहः ७. १००, ६; १०. २७, २४.

गूहंत १. ८६, १०.

गूहता २. ४०, २.

गूहते १०. २७, २४.

गूहथः ५. ६३, ४.

गूहंति १०. १०८, ४.

गूहंतीः ४. ५१, ९.

गूहमाना ६. १०४, १७.

गृणतः ३. ६१, १; ४. १७, ५; ५. ३३, ७; ६. २३, ४; २४, २; ४९, ११; ७. १२, २; ९. ४३, ६; १०. २२, १५; ११५, ५; ९; १४८, ४.

गृणतां ६. ४४, १३; ४५, १७; १०. ८९, १६.

गृणते १. ४४, ६; ५८, ९; ९४, ९; ११३, १७; २. ४, ९; ३. ३०, १५; ५९, ५; ४. ११, २; २४, १; ६. ४, ८; ६, ७; ११, ३; ३१, ४; ३९, १; ५; ४०, १; ४९, ७; ६२, ५; ११; ६५, ६; ६६, ९; ७. ३, १०; ३६, ९; ७७, ४; ९. ६९, १०; ८९, ६; १०. ३०, १२; ४९, १; ८७, ११.

गृणत्ऽअर्यः ६. ८, ५.

गृणत्ऽसु ५. ८६, ६^{2}; ८. १३, १२.

गृणंत ८. ३, ७.

गृणंतः १. ९, ९; १५२, ५; १७७, ५; ३. १७, ४; ४. १०, ४; १६, ३; २९, ५; ५. ८, ४; ६. ३३, ५; ६८, ८; ७. ५३, १; ६०, १; ७८, २; ८. ३, १३; ५, २७; २७, १३; ९. २९, २; १०. १०४, ४; १२२, ८.

गृणंतं १. ५८, ८; ९; ३. २०, ४; ४. २९, ४; ५. ७५, ८; ६. २६, ४; ७. ५७, २.

गृणंति १. १४, २; ४८, ११; ४. ३४, १०; ५. ७९, ४; ६. ३४, ३; ६५, ५; ७. ३८, ३; ८. ४६, ३; ५४, १; ७५, १०; १०. ६, ५.

गृणंति १. १००, १७; २. ४३, १; ३. ३४, ७; ४. ३२, ११; ६. ४५, ३३; ७. १८, २४; ३८, ४; १०. ७, २; ४९, ११.

गृणाति ५. २७, ३; ७. ३८, ४.

गृणाति १. ४८, ४; १४७, २; ७. २६, ५; ८. १५, ९.

गृणातु ५. ४१, १९; १०. १३९, ५.

गृणानः १. ३५, १०; ६२, ५; १८१, ९; १८९, ६; २. १५, ८; ४. १६, १; ८; २१; १७, १८; २९, १; ५. ४, ९; १६, ५; ६. १६, १०; १७, १; १८, १४; ३२, २; ३६, ४; ३९, ५; ५०, ६; ७. ८, ५; ५६, १८; ८. ९३, १०; ९. ६२, २४; ६५, २५; ९७, ४९; १०. ६१, २६; १०४, ३; १११, ४; १३८, ४; १४७, ५.

गृणाना १. ११७, ११; ३. ६२, १८; ५. ४१, १९; ६. ६३, २; ६८, ८; ७. ७५, ५; ७९, ४; ९६, ३; ८. १०१, ८.

गृणानाः ३. ५०, ३; ४. ३४, ५; ५. ५५, १०; ५९, ८; ९. १३, ३; ६२, २२.

गृणाने इति १. १६०, ५.

गृणामि ७. १००, ५.

गृणीत ८. ३, १३; १०. १५, ६.

गृणीतः ३. ६, १०.

गृणीतां १०. ४७, ८.

गृणीते ५. ४१, १०.

गृणीते १. ७९, १२; ४. २५, ७.

गृणीमसि २. ३३, ८.

गृणीमसि १. ४२, १०; ५३, २; ६४, १२; १५५, ४; २. ३४, १४; ८. १५, ४; ७१, १५; १०. ८४, ५; ९२, १४.

गृणीषणि ६. १५, ६; ८. १२, १९.

गृणीषे ६. ३५, ५; ४४, ४; ८. ६५, ५.

गृणीषे १. १४६, १; १८६, ३; २. २०, ४; ३३, १२; ५. ३४, ९;

७. ६, ४; २४, १६; ६६, ७; ९७, ३; १०. १२२, १.
गृणीहि ८. १०२, १२.
गृणीहि १. १०, ४; १५, ३; ४८, १४; २. ९, ४; ३. ५३, ३; ५. ५३, १६; ६. ६८, ३; ९. ८४, १.
गृणे ५. ६, २; ८. २७, ८; ३३, ५; ६२, ८; ७०, १.
गृणे १. १४३, ६; ६. १५, ७; ८. ३, ४; २३, ७; १०. १५०, ३.
गृत्सः ३. ४८, ३; ४. ५, २; ७. ४, २; ८७, ५.
गृत्सं ३. १९, १; ७. ८६, ७.
गृत्सऽमदाः २. १९, ८; ४१, १८.
गृत्सऽमदासः २. ४, ९; ३९, ८.
गृत्सस्य १०. २५, ५; २८, ५.
गृत्साय ३. १, २.
गृध्नुः १. ७०, ६; १६२, २०.
गृध्यंतं ४. ३८, ३.
गृध्रः १. १९०, ७.
गृध्रंऽयातुं ७. १०४, २२.
गृध्रस्य १०. १२३, ८.
गृध्राःऽइव २. ३९, १.
गृध्राः १. ८८, ४; ११८, ४; ९. ९७, ५७.
गृध्राणां ९. ९६, ६.
गृध्रात् ५. ७७, १.
गृभे ७. ४, ३.
गृभयंतः १. १४८, ३.
गृभा ८. १७, १५.
गृभात् ७. २१, २.
गृभाय ८. १७, ५.
गृभाय १. ८१, ७; ९१, ४; २. २८, ६; ३. ३६, २; ४. ४, १५; ५. ८३, १०; ६. ४७, २८; ८. ७०, १२[2]; ८१, १; १०. ४४, ४; ११६, ७.
गृभायत ७. १०४, १८.
गृभायत ८. ६९, १०.
गृभायति १. १४०, ७.
गृभीतः १. २४, १२; १३; १६४, ३८.
गृभीतऽतातये ५. ७४, ४.
गृभीतं ७. २४, २.
गृभीताः ६. ४६, १४.
गृभीतान् १. ९३, ५; १०. ७९, ७.
गृभीतां १. १६२, २.
गृभे ८. १०, ३.
गृभ्णत ९. १४, ७.
गृभ्णते ९. ८६, ४३.
गृभ्णंति ८. ७२, ३; ९. १, ७.
गृभ्णंति १. १६२, १५.
गृभ्णाति ९. ७८, १; ८३, ४.
गृभ्णाति १. ५५, २; ७. १०१, ३; १०३, ४.
गृभ्णामि १०. ८५, ३६; १४५, ४.
गृभ्णीत ९. ४६, ४; १०६, ३; १०. ६२, १.
गृभ्णे ८. ४५, ३९.
गृष्टिः ४. १८, १०.
गृहः १०. ११९, १३.
गृहते ५. ३२, १२.
गृहऽपतिः १. १२, ६; ३६, ५; ६०, ४; २. १, २; ४. ९, ४; ६. १५, १३; ४८, ८; ७. १६, ५; ८. ६०, १९; १०. १२२, १.
गृहऽपतिं ४. ११, ५; ५. ८, १; २; ६. १६, ४२; ५३, २; ७. १, १; १०. ११८, ६.
गृहऽपते ६. १५, १९.
गृहऽपत्नी १०. ८५, २६.
गृहं १. २२, ४; ४९, १; ११०, २; १३५, ७; २. ४१, २; ४. ४९, ३; ५. २९, ९; ६. २८, ६; ७. ७४, ४; ८८, ५; ८९, १; ८. ५, ५; १३, १०; २२, ३; ६९, ७; ७३, ७; ८५, ६; ९. ४९, २; १०. १६, १०; २२, ६; ४०, ३; ११; १४; ८५, १०; ८६, २२; १७१, २.
गृहंऽमेधासः ७. ५९, १०.
गृहऽमेधीयं ७. ५६, १४.
गृहंऽगृहं १. १२३, ४; १२४, ११; ८. ९१, २.
गृहवे १०. ११७, ३.
गृहाः ५. ७६, ४; १०. १४२, ८.
गृहाण १०. १०३, १२.
गृहाणां २. ४२, ३.
गृहात् ७. १८, २१.
गृहान् ६. ५४, २; १०. ८५, २६; ८६, २०.
गृहामहि ८. २१, १६.
गृहायं १. १४०, १२.
गृहासः १०. १८, १२.
गृहे १. १३, १२; ८४, १५; १६१, ११; १९१, १०; ३. ५३, ६; ६०, ५; ४. ३, ४; १८, ३; ४६, ६; ४९, ६; ८. १०, १; १९, ११; २२, ८; २६, १७; ३१, ४; ९. १००, २; ८; १०. ६२, ४; ८५, २७; ४२; १००, ६; १२२, ५; १८६, ३.
गृहेऽगृहे १. २८, ५; ७१, ४; ५. ११, ४; १०. ९१, २.
गृहेभ्यः १. १२०, ८; ३. ५३, २०.
गृहेषु १०. १६५, २.
गृह्णातु ४. ५७, ७.
गेह्यं ३. ३०, ७.
गैरिऽक्षितस्य ५. ३३, ८.
गोऽअग्रया १. ५३, ५; ९. ७१, ८.
गोऽअग्राः १. ९०, ५; १६९, ८; ६. ३९, १.
गोऽअग्रान् १. ९२, ७.
गोऽअग्रां २. १, १६; २, १३.
गोऽअजनासः ७. ३३, ६.
गोऽअर्णसः १. ११२, १८.
गोऽअर्णसं १०. ३८, २.
गोऽअर्णसा २. ३४, १२.
गोऽअर्णसि १०. ७६, ३.
गोऽआशिरः १. १३७, १[2]; १८७, ९; २. ४१, ३; ८. ५२, १०; ९. ६४, २८.
गोऽआशिरं ३. ३२, २; ४२, १; ७; ८. १०१, १०.
गोऽइषः ४. ४१, ७; १०. ७६, ७.
गोऽइषः ४. १३, २; ४०, २.
गोऽइषे ८. २४, २०.
गोऽइष्टये ८. ६१, ७; ७५, ११; ९. ६६, १५; १०८, १०.
गोऽइष्टिषु १. ३६, ८; ५. ६३, ५; ६. ५९, ७; ८. २४, ५; ९. ७६, २; १०. १४७, २.

गोऽईष्टौ १. ९१, २३; ३. ४७, ४; ६. ३१, ३; ४७, २०; ८. ५७, ३; १०. ६१, २३; १०२, २.

गोऽऋजीकं ६. २३, ७; ७. २१, १.

गोऽऋजीका ३. ५८, ४.

गोऽएर्पणः १. १३२, ३[2]; ७. २०, ५; ८. १७, १५.

गोऽएर्पणं ६. ५६, ५; ७. २३, ३.

गोऽओपशा ६. ५३, ९.

गोः १. २८, ९; ५३, २; ६१, १२; ८४, १५; १२१, २[2]; ७; ९; १५८, २; १६३, ७; १८०, ३; ५; १८१, ८; २. १४, १०; ३. १, २३; ३०, १०; ३८, ७; ३९, ६; ५५, १; ८; ४. १, १६; ३, ९; ५, ३; १०; २२, ४; ८; २३, ६; २८, ५; ४४, १; ५. ४१, १८; ४५, ६; ७. १८, २२; ८. ३२, ५; ५२, ५; ९. ६५, २५; ७१, ५; ७९, ४; ९१, ३; १०१, ११; १०. १२, ३; ९६, ११; १००, १२; १११, ३.

गोऽकामाः १०. १०८, १०.

गोऽघ्नं १. ११४, १०.

गोऽजाः ४. ४०, ५.

गोऽजाताः ६. ५०, ११; ७. ३५, १४.

गोऽजित् ९. ५९, १; ७८, ४.

गोऽजितः ३. ३१, २०.

गोऽजिता १. १०२, ६.

गोऽजिते २. २१, १.

गोऽजीरया ९. ११०, ३.

गोतम १. ७९, १०.

गोतमः १. ६२, १३; ७८, २; ८८, ५; १८३, ५.

गोतमस्य १. ११६, ९.

गोतमाः १. ७८, १; ४. ३२, १२; ८. ८८, ४.

गोतमात् ४. ४, ११.

गोतमाय १. ८५, ११.

गोतमासः १. ६०, ५; ६१, १६; ८८, ४.

गोतमेभिः १. ६३, ९; ७७, ५; ९२, ७.

गोत्रऽभित् ६. १७, २.

गोत्रऽभिदं २. २३, ३; १०. १०३, ६.

गोत्रं १. ५१, ३; २. २३, १८; ८. ५०, १०; ९. ८६, २३.

गोत्रस्य ८. ६३, ५; १०. १२०, ८.

गोत्रा २. १७, १; ३. ३०, २१; ४३, ७; ४. १६, ८; ६. ६५, ५; १०. ४८, २.

गोत्राणि ३. ३९, ४; १०. १०३, ७.

गोऽदत्र ८. २१, १६.

गोऽदुरे ८. ९२, ११.

गोऽदाः १. ४, २; ३. ३०, २१; ४. २२, १०; ५. ४२, ८; ८. ४५, १९.

गोऽदुहः ८. ५२, ४.

गोऽदुहे १. ४, १.

गोधा ८. ६९, ९; १०. २८, १०; ११.

गोऽधायसं १०. ६७, ७.

गोऽधुक् १. १६४, २६.

गोनां १. ६९, २; १२६, २; २. ३०, ५; ४. २०, ८; ५. ३, ३; ६, ७; २७, २; ८. १६, ७; ८. ५, ३७; ६, ४७; ७८, १; ९. ७४, ८; ८७, ३; ९; ९७, ३१; ४३; १०. ८, ९; ४७, १; ८०, ५; १०८, ८.

गोऽन्योघाः ९. ९७, १०.

गोऽपतिः १. १०१, ४; ३. ३१, २१; ४. २४, १; ३०, २२; ६. २८, ३; ७. ९८, ६; ८. १४, २; ६२, ७; १०. १०८, ३.

गोऽपतिं ७. १८, ४; ८. ६९, ४; ९. ३५, ५; ९७, ३४; १०. ४७, १; ६७, ८; १६६, १.

गोपती इति गोऽपती ९. १९, २.

गोऽपते ८. २१, २.

गोऽपते ३. ३०, २१; ६. ४५, २१.

गोऽपतौ १०. १९, ३.

गोपं १०. ६१, १०.

गोपऽयत्यं ८. २५, १३.

गोऽपरीणसा ८. ४५, २४; १०. ६२, १०.

गोपवनः ८. ७४, ११.

गोपा ७. ९१, २; ८. २५, १; १०. ४०, १२.

गोपा ७. ६२, ९; ७. ६४, २.

गोपाः १. २२, १८; ९४, ५; ९६, ४; १०१, ११; १६३, ५; १६४, २१; २. ९, २; ६; २३, ६; २७, ४; ३. १०, २; १५, २; ३१, १४; ५५, १०; ४. १६, १७; ५. २, ५; ११, १; १२, ४; ३१, १; ६. ७, ७; ९, ३; ५१, १५; ७. १३, ३; ५१, २; ५२, २; ५६, १८; ६०, २; ८. २८, ३; ३१, १३; ४८, ९; ९. ७३, ८; १०. ७, ७; ८, ५; १७, ३; १९, ४; ५; २३, ६; २५, ७; ४८, १०; ६९, ५; ११८, ७; १२८, ६; १३९, १.

गोपाःऽइव ८. ४१, ४.

गोपाजिह्वस्य ३. ३८, ९.

गोपान् ६. ५१, ३.

गोपाभिः ६. ८, ७.

गोपां १. १, ८; ९१, २१; ९६, ७; १६४, ३१; ३. ४३, ५; ६. ४९, १५; ५२, ३; ८. ४२, २; ९. ५, ९; ४८, ४.

गोपायतं ६. ७४, ४.

गोपायंति १०. १५४, ५.

गोपावत् ७. ६०, ८.

गोऽपीथाय १. १९, १.

गोऽपीथे ५. ६५, ६; १०. ३५, १४; ७७, ७.

गोऽपीथ्याय १०. ९५, ११.

गोपौ २. ४०, १.

गोपौ ५. ६३, १.

गोऽबंधवः ८. २०, ८.

गोऽभाजः १०. ९७, ५.

गोऽभिः १. ७, ३; १६, ९; २३, १५; ५३, ४; ६२, ५; ९५, ८; १३४, २; १५१, ८; २. १५, ४; २५, २; ३०, ७; ३. ३०, २०; ३५, ८; ५०, ३; ४. ३, ११; २७, ५; ५. १, ३; २, ५, ३, २; २०, ४; ४२, ४; ४५, ८; ८०, ३; ६. ४७, २६; २७; ७५, ११; ७. १८, २; ४१, ३; ५४, २; ९०, ६; ८. २, ३; ६; २०, ८; ८२, ५; ९. २, ४; ६, ६; ८, ५; १०, ३; १४, ३; ३२, ३; ४३, १; ४५, ३; ४६, ४; ५०, ५; ६१, १३; ६६, १३; ६८, ९; ८४, ३; ८५, ५; ८६,

२७; ४७; ९१, २; ९६, २२; ९७, ४५; १०३, २; १०४, ४; १०७, २; ९; १८; २२; १०९, १५; १७; १०. ७, २; १६, ७; ३१, ४; ४२, १०; ६४, ११; ६८, २; १२; १०८, ७; १११, २.

गोभिःऽइव ८. २४, ६.

गोभ्यः ८. ४५, ३०; १०. १६५, ३.

गोऽमघा ६. ३५, ३; ७. ७१, १.

गोऽमघाः ६. ३५, ४.

गोऽमत् १. ९, ७; ३०, १७; ४८, १२; ९२, १६; १९०, ८; २. ४१, ७; ५. ५७, ७; ७. २७, ५; ७५, ८; ७७, ५; ९४, ९; ८. २२, १७; ४६, ५; ४९, १०; ९३, ३; ९. ४१, ४; ४२, ६; ६१, ३; ६९, ८; १०५, ४; १०. ३६, १३; ४२, ७.

गोऽमतः १. ११, ३; ५; ७९, ४; ३. १६, १; ४. ३१, १३; ३२, ६; ७; ५. २३, २; ६. १०, ३; ४५, २३; ६२, ११; ७३, ३; ७. ८१, ६; ८. ३, १; १३, १४; २१, ११; २५, २०; ३२, ९; ४५, १०; २८; ४९, ९; ८२, ६; ९२, ३०; ९४, ६; ९५, ४; ९. ५४, ४; ६७, ५; १०. २५, ११.

गोऽमता ७. ७२, १.

गोऽमति १. ८६, ३; ५. ३४, ५; ७. २७, १; ३२, १०; ८. २१, ८; ४६, ९; ५१, ५; ७०, ६.

गोऽमति १. ९२, १४.

गोऽमती १. ८, ८.

गोऽमतीः १. ४८, २; १५; ११३, १८; १२३, १२; ५. ६१, १९; ७९, ८; ७. ४१, ७; ८. ५, ९; २३, २९; ९. ६२, २४.

गोऽमतीनां २. २८, २.

गोऽमतीं ८. ६, २३.

गोऽमतीं ८. २४, ३०; १०. ७५, ६.

गोऽमतीषु ४. २१, ४.

गोऽमते ९. ७७, ३.

गोमत्ऽभिः ६. ४५, २१.

गोऽमतं १. ८३, ४; ४. १, १५; १६, ६; ३४, १०; ५. ४, ११; ६. ४५, २४; ८. २, २४; ५, १०; ६, ९; ३३, ३; ८८, २; ९. २०, २; ३३, २; ६२, १२; ६३, १२; १४; १८; ६७, ६; १०. २५, ५; ७४, ४; १५६, ३.

गोऽमथे १०. ६२, २.

गोऽमातरः १. ८५, ३.

गोऽमान् ४. २, ५; ८. ४, ९; ९. १०७, ९.

गोऽमायुः ७. १०३, ६; १०.

गोऽरभसं १. १२१, ८.

गोऽवपुषः १०. ६८, ९.

गोऽवित् ९. ५५, ३; ८६, ३९; १०. १०३, ५.

गोऽविदं १. ८२, ४; ८. ५३, १; १०. १०३, ६.

गोऽविंदुः ९. ९६, १९.

गोऽशर्ये ८. ८, २०.

गोऽशर्ये ८. ४९, १०; ५०, १०.

गोऽश्रीताः १. १३७, १.

गोऽश्रीते ८. २१, ५.

गोषुं १. २९, १–७; ३७, ५; ७०, ५; ७१, ९; ८३, १; ११४, ८; १२१, १५; १५१, १; २. २५, ४; ३. ३१, १०; ३९, ४; ४. ३८, ४; ५. ३४, ८; ४५, ९; ६. १९, १२; २५, ४; २६, २; २८, ८; ३२, ३; ३५, २; ४४, २४; ७. ३२, १६; ८. ५, २६; ३२, २५; ४७, १४; ७१, ५; ७५, ७; ९. १६, ६; ६२, १९; ८६, १२; ९६, ७; १०५, ४; १०. ६१, ४; ७३, ९; ९९, ४; १०६, ११.

गोषुऽयुधः ६. ६, ५; १०. ३०, १०.

गोषुऽयुधं १. ११२, २२.

गोऽसखा ८. १४, १.

गोऽसखायं ५. ३७, ४.

गोसऽतमाः ६. ३३, ५.

गोऽसनः ४. ३२, २२.

गोऽसनिं ६. ५३, १०.

गोऽसाः ९. २, १०; ६१, २०; १०. ९५, ३.

गोऽसाता ८. ८४, ७; १०. ३८, १.

गोऽसां ९. १६, २.

गोऽस्थं ८. ४३, १७; १०. १६९, ४.

गोस्थात्ऽइव १०. ९७, ८.

गोऽस्थे १. १९१, ४; ६. २८, १; १०. १६९, ३.

गोऽहा ७. ५६, १७.

गोहे ४. २१, ६–८.

गौः १. १६४, १७; २८; २९; १७३, ३; ८; ३. ७, २; ३०, १४; ३१, ११; ४. ५, ९; ४१, ५; ६. ४५, २६; ८. ९४, १; १०. २७, २२; ३१, ६; १०; ६५, ६; १८९, १.

गौःऽइव ५. ५६, ३; ८. ३३, ६; १०. १४५, ६.

गौरः १. १६, ५; ४. ५८, २; ८. ४, ३; ४५, २४; १०. ५१, ६.

गौरस्य ४. २१, ८; १०. १००, २.

गौराऽइव ७. ६९, ६.

गौरात् ७. ९८, १.

गौरिऽवीतेः ५. २९, ११.

गौरी इति ९. १२, ३.

गौरीः १. १६४, ४१.

गौरौऽइव ५. ७८, २; ८. ८७, १; ४.

गौर्यः १. ८४, १०.

गौर्ये ४. १२, ६.

ग्धेतिग्ध १. १५८, ५.

ग्नाः १. २२, १०; ६१, ८; ४. ९, ४; ५. ४३, १३; ४६, २; ८; ६. ५०, १५; ६८, ४; १०. ९५, ७.

ग्नाःपतिः २. ३८, १०.

ग्नाःऽपत्नीभिः ४. ३४, ७.

ग्नाभिः २. ३१, ४; ६. ४९, ७; ७. ३५, ६; १०. ६६, ३; ९२, १४.

ग्नां ५. ४३, ६.

ग्नावः १. १५, ३; २. १, ५.

ग्नासु १. १६१, ४.

ग्मः १. २५, २०; ३७, ६; ५. ३८, ३; १०. २२, ६; ४९, २.

ग्मन् १०. २९, ५; १२३, ४.

ग्मन् १. ६५, १; ३. ३८, २; ५४, १४; ४. ३४, ५; ४३, ६; ५. ३३, १०; ४९, ४; ६. १, २; ३; १०. ४६, २.

ग्मंतं १. १२२, ११.
ग्मंता १०. २२, ६; ३२, १.
ग्रथितं ९. ९७, १८.
ग्रथिनः ७. ६, ३.
ग्रंथिनी १०. ९५, ६.
ग्रंथिं ९. ९७, १८; १०. १४३, २.
ग्रभणऽवत् १. १२७, ५.
ग्रभाय ७. ४, ८.
ग्रभीष्ट २. २९, ५.
ग्रसिता १. ११२, ८; १०. ३९, १३.
ग्रसिष्ठः १. १६३, ७.
ग्रसेता ३. ३५, ३.
ग्रहान् १०. ११४, ५.
ग्रामं ८. ८१, १; ९. १०६, ३.
ग्रामः ३. ३३, ११.
ग्रामऽजितः ५. ५४, ८.
ग्रामऽनीः १०. ६२, ११; १०७, ५.
ग्रामं १०. २७, १९; १४६, १; १४९, ४.
ग्रामाः २. १२, ७.
ग्रामासः १०. १२७, ५.
ग्रामे १. ११४, १.
ग्रामेभिः १. १००, १०.
ग्रामेषु १. ४४, १०.
ग्राम्याः १०. ९०, ८.
ग्रावऽग्राभः १. १६२, ५.
ग्रावऽभिः ३. ४२, २; ५. ४८, ३; ९. ८०, ४; ८२, ३.
ग्रावऽभ्यः १०. ९४, १.
ग्रावऽहस्तासः १. १५, ७.
ग्रावा १. २८, १; ८३, ६; ८४, ३; १३५, ७; ५. ३१, १२; ४०, २; ८. ३४, २; १०. ३६, ४; ६४, १५; ७०, ७; १००, ९.
ग्रावाऽइव ४. ३, ३; ५. २५, ८; ३६, ४.
ग्रावाणः १. ८९, ४; ३. ३०, २; ५. ३१, ५; ३७, २; ६. ५१, १४; ७. ३५, ७; १०४, १७; ८. २७, १; ४२, ४; १०. ७६, ६; ७८, ६; ९२, १५; ९४, २; १०८, ११; १७५, २–४.
ग्रावाणः १०. ९४, १०; १७५, १.
ग्रावाणं ७. ३३, १४; ८. २६, २४.
ग्रावाणाऽइव २. ३९, १.
ग्राव्णः ३. ५७, ४; ५. ४०, ८.
ग्राव्णां ९. ६७, १९; ११३, ६.
ग्राव्णां १०. ३५, ९; ८५, ४.
ग्राहिः १०. १६१, १.
ग्राह्यः १०. १०९, ३.
ग्रीवाः ६. ४८, १७.
ग्रीवाभ्यः १०. १६३, २.
ग्रीवायां ४. ४०, ४.
ग्रीष्मः १०. ९०, ६.
ग्लपयंति १. १६४, १०.

घ

घ १. ५, ३; १८, ४; २७,२; ३०, ८; १४; ३६, ७; ३७, ११; ४८, ५; ५३, ७; ५४,७; ८२,४; १०९, २; ११२, १९; १३२, ३; १६१, ८³; १६२, ८; १७८, २; १८९, ६; २. १५, १; ३४, १४; ३. १०, ३; १८, ५; २८, २; ३६, ३; ४. १५, ५; २७, २; ३०, ८; ९; २२; ३२, २; २०; ५१, ७; ५. ६१, ८; ८५, ८; ६. ४५, २३; ५६, २; ७. २९, ४; ४५, ३; ८. १, ३०; २, १७; २२; २६; ३३; १२, १६; १९, १७; २०, २१; २१, १७; २३, १९; ३२, ७; ३३, १; १७; १८; ४३, ३; २९; ४४, २३; ४५, १; ४७, ४; १५; ६६, ११; १५; ७५, १४; ९३, १; १०. १०, ३; १०; २५, १०; ४३, २; ६१, १८; ९३, ४; ९४, १३.
घनः १. ४, ८; ८. ९६, १८.
घनं ३. ४९, १; ४. ३८, १.
घना १. ८, ३.
घनाऽइव १. ३६, १६; ६३, ५; ९. ९७, १६.
घनावनः १०. १०३, १.
घनिघ्नत् ९. ९०, ६.
घने ६. २६, ८.
घनेन १. ३३, ४.
घर्मः १. १६४, २६; ३. २६, ७; ५. १९, ४; ३०, १५; ४३, ७; ७. ७०, २; ८. ९, ४.
घर्मं १. ११२, १; ७; ११९, २; ६; १६४, २८; १८०, ४; ३. ५३, १४; ५. ७३, ६; ७६, १; ८. ९, ७; ७३, ३; ८७, २; ८९, ७; १०. १६, १०; १८१, ३.
घर्मसत्ऽभिः १०. १५, ९; १०.
घर्मऽस्तुभे ५. ५४, १.
घर्मऽस्वरसः ४. ५५, ६.
घर्मऽस्वेदेभिः १०. ६७, ७.
घर्मा १०. ११४, १.
घर्माऽइव १०. १०६, ८.
घर्माः ७. १०३, ९.
घर्मासः ७. ३३, ७.
घर्मिणः ७. १०३, ८.
घर्मे १०. ८०, ३.
घर्म्येऽस्था १०. १०६, ५.
घसः ३. ५२, ३; ४. ३२, १६.
घसत् १०. ८६, १३.
घासिं १. १६२, १४.
घृणा ६. ३, ७.
घृणा १. ५२, ६; १४१, ४; ४. ४३, ६; ५. ७३, ५; ९. १०७, २०.
घृणात् १. १३३, ६.
घृणिऽइव २. ३३, ६.
घृणिऽवान् १०. १७६, ३.
घृणे ६. १५, ५.
घृणेः ६. १६, ३८.
घृणेन १०. ३७, १०.
घृतऽअन्नः ७. ३, १.
घृतऽअन्नौ ६. ६७, ८.
घृतऽआसुतिः १. १५६, १.
घृतऽआहवन १. १२, ५; ४५, ५.
घृतऽआहवनं ८. ७४, ५.
घृतऽकेशं ८. ६०, २.
घृतऽदुहः ९. ८९, ५.
घृतऽनिर्निक् १०. १२२, २.
घृतऽनिर्निक् २. ३५, ४; ३. १७, १; २७, ५.
घृतऽनिर्निजः ४. ३७, २.
घृतऽपदी १०. ७०, ८.
घृतऽपृचा ६. ७०, ४.
घृतऽपृष्ठः १. १६४, १; ५. ३७, १.
घृतऽपृष्ठं १. १३, ५; ५. ४, ३; १४,

५; **७.** २, ४; **१०.** ३०, ८; १२२, ४.
घृतऽपृष्ठाः **१.** १४, ६.
घृतऽप्रतीकः **३.** १, १८; **५.** ११, १.
घृतऽप्रतीकं **१.** १४३, ७; **१०.** २१, ७.
घृतऽप्रतीका **१०.** ११४, ३.
घृतऽप्रतीकां **७.** ८५, १.
घृतऽप्रयाः **३.** ४३, ३.
घृतऽप्रसत्तः **५.** १५, १.
घृतऽप्रुषः **६.** ४४, २०; **८.** ५९, ४; **१०.** ७८, ४.
घृतऽप्रुषं **१.** ४५, १; **७.** ४७, १.
घृतऽप्रुषा **२.** ३, २.
घृतऽप्वः **१०.** १७, १०.
घृतं **१.** ८५, ३; ८७, २; ११०, ६; १२५, ५; १३४, ६; १३५, ७; १६८, ८; **२.** ३, ११^{3}; ५, ६; ३५, ११; १४; **३.** २, १; **४.** १, ६; १०, ६; ५८, ४; **५.** ५, १; १२, १; ८६, ६; **६.** १०, २; ७०, २; **७.** ४१, ७; ९५, २; **८.** ६, १९; ७, १९; १२, ४; १३; ३९, ३; १०२, ११; **९.** ३१, ५; ४९, ३; ६२, ९; ६७, ११; १२; ७४, ४; ८२, २; ८६, ३७; **१०.** १२, ३; ३०, १३; ५१, ८; ६९, २^{3}; ८२, १; ९१, १५; ९६, १; ९९, ४; १५४, १.
घृतंऽइव **४.** ५७, २.
घृतऽयोनिं **३.** ४, २; **५.** ८, ६.
घृतयोनी इति घृतयोनी **५.** ६८, २.
घृतऽवत् **१.** २२, १४; ६४, ६; **३.** ५, ६; ३१, ११; ५९, १; **७.** ४७, ३; **१०.** १४, १४; ६४, ९; ६५, ८.
घृतऽवती **६.** ११, ५.
घृतवती इति घृतऽवती **६.** ७०, १.
घृतवत्ऽभिः **२.** २६, ४; **७.** ३, ७.
घृतऽवतः **३.** २१, २; **१०.** २९, ६.
घृतऽवतं **१.** ३४, १०; १४२, २; **३.** ५, ७; **६.** १५, १६; **९.** ८२, १; **१०.** ४५, ९; ९१, ४; १४८, ५.
घृतऽवति **९.** ९६, १३.
घृतऽवर्तनिः **७.** ६९, १.
घृतऽवृधा **६.** ७०, ४.
घृतऽश्चुतः **३.** २१, ३; **७.** ९६, ५; **८.** ५९, ४; ५; **९.** ७४, ६; ७७, १; **१०.** १८, १२.
घृतऽश्चुतं **२.** ११, ७; **८.** ८, १५; १६; ५१, १०; ५४, १.
घृतऽश्चुता **५.** १४, ३.
घृतऽश्रियं **५.** ८, ३.
घृतऽश्रिया **६.** ७०, ४.
घृतऽश्रीः **१.** १२८, ४; **१०.** ६५, २.
घृतऽस्नाः **४.** ६, ९; **८.** ४६, २८.
घृतऽस्नुः **५.** ७७, ३; **९.** ८६, ४५; **१०.** १२२, ६.
घृतस्नुऽना **६.** ५२, ८.
घृतऽस्नुवः **१.** १६, २.
घृतऽस्नुवा **३.** ६, ६.
घृतस्नू इति घृतऽस्नू **३.** ४१, ९; **४.** २, ३.
घृतस्नू इति घृतऽस्नू **१.** १५३, १; **१०.** १२, ४.
घृतऽस्नूः **२.** २७, १.
घृतस्नो इति घृतऽस्नो **५.** २६, २.
घृतस्य **१.** १२५, ४; १२७, १; **३.** १, ७; ८; २१, १; ४; **४.** ५८, १; २; ५–१०; **५.** ६२, ४; **७.** ६४, १; **८.** ६, ४३; १०२, १६; **१०.** ९५, १६.
घृतऽहस्ता **७.** १६, ८.
घृताचीं **१.** १६७, ३; **३.** ६, १; ३०, ७; **४.** ६, ३; **५.** २८, १; ४३, ११; **६.** ६३, ४; **७.** १, ६; ८४, १.
घृताचीः **७.** ५, ५; ४३, २; ६०, ३; **८.** ४४, ५; **१०.** १३९, २.
घृताची **१.** २, ७; **३.** १९, २; **१०.** ७०, १.
घृताच्या **३.** २७, १.
घृतात् **८.** २४, २०; ४३, १०.
घृतानि **१.** १८८, ५; **१०.** ११८, २.
घृतासुती इति घृतऽआसुती **६.** ६९, ६.
घृतासुती इति घृतऽआसुती **१.** १३६, १; **२.** ४१, ६.
घृते **२.** ३, ११; **९.** १०१, १२; **१०.** ८०, ६.
घृतेन **१.** ७२, ३; ८४, १८; ९३, ८; १०; १५७, २; १६४, ४७; **२.** ३, ४; १०, ४; **३.** ५, ८; १८, ३; **५.** १, ७; ११, ३; १४, ६; ४२, ३; ८३, ८; **६.** १६, ११; ७०, ४; ७१, १; **७.** ८, १; १४, २; ६२, ५; ६४, ४; **१०.** १७, १०; १९, ७; ३६, ६; ५९, ५; ६९, १; २; ११०, १०; ११८, ४; ६.
घृतेभिः **२.** ७, ४; **८.** १९, २२; २३.
घृतैः **१.** १५३, १; **३.** ९, ९; ६२, १६; **५.** ८, ७; **७.** ६५, ४; **८.** ५, ६; ४३, २२; ४४, १; **१०.** ५, ४; ७९, ५.
घृषुः **१०.** १४४, ३.
घृषुं **१.** ६४, १२; **१०.** २७, ६.
घृषौ **६.** ४६, ४.
घृष्वयः **१.** ८५, १; १६६, २; **९.** २१, १; १०१, ८.
घृष्वये **१.** ३७, ४; **४.** ३२, ६; ९; **८.** ६४, १२; **९.** २, ८; १६, १.
घृष्विऽराधसः **७.** ५९, ५.
घृष्वे **४.** २, १३.
घृष्वैः **३.** ४६, १; **७.** ९३, २.
घोरः **७.** २८, २.
घोरऽचक्षसे **७.** १०४, २.
घोरं **२.** १२, ५; **७.** २०, ६; **९.** ८९, ४.
घोरया **८.** ९२, १५.
घोरऽवर्पसः **१.** १९, ५; ६४, २.
घोरस्य **४.** ६, ६.
घोरा **४.** १६, १७; **६.** ६१, ७; ६७, ४.
घोराः **१.** १६७, ४; **१०.** १०८, १०.
घोराणां **१.** १६९, ७.
घोरासः **७.** ६६, १३; **१०.** ९२, ३.
घोरे **१०.** ९५, १.
घोरेण **१०.** ३४, १४.
घोषः **३.** ३०, १६; ३१, १०; **७.** २३, २; ८३, ३; **१०.** ३३, १; १०३, ९; १६८, १.
घोषतः **८.** २५, ४.

घोषथः **१.** १५१, ४.

घोषे **३.** ७, ६; **५.** ५४, १२; **१०.** ८४, ४; ९४, १; १२३, ४.

घोषयः **९.** १०८, ३.

घोषा **१०.** ४०, ५.

घोषाऽइव **१.** १२२, ५.

घोषाः **८.** ६३, ७; **१०.** ६८, १; १०३, १०; १६८, ४.

घोषात् **१.** १३९, ८; **६.** ३८, २.

घोषात् **५.** ३७, ३.

घोषान् **३.** ३३, ८; **६.** ७५, ७.

घोषायै **१.** ११७, ७.

घोषि **४.** ४, ८; **६.** ५, ६.

घोषे **१.** १२०, ५.

घोषेण **८.** ३४, २.

घोषैः **१.** १८१, ५.

घ्नन् **४.** १२, २; १७, १०; **५.** १४, ४; ३१, ७; **६.** ७३, २; **८.** ४३, २६; **९.** २७, १; **१०.** ९९, ३.

घ्नंतः **१.** ३६, ८; **६.** १९, १३; **७.** ९२, ४; **९.** १७, १; ४१, १; ६३, २६.

घ्नंतं **१.** ४१, ८; **३.** ३०, २२; **८.** ४३, २३.

घ्नंतिं **१.** ४१, ३; **८.** ८४, ९.

घ्नंति **२.** २७, १३.

घ्नंतु **७.** १०४, १७.

घ्नंसं **१.** ११६, ८; **५.** ४४, ७; **७.** ६९, ४.

घ्नंसे **५.** ३४, ३.

च

च **१.** २, ५–७; ७, ४; ८, ५; १०; १०, ४; ५; १२, १०; १३, १; ६; १४, १; १५, ९; १७, ६; १८, ५; २०, ५; २२, १३; २३, २०^{२}; २१; २४, १^{२}; २; २५, ११; १९; २०; २६, ५; ८; २७, ३; २८, ३; ३१, ७; ९; १२; १७; ३२, १३^{२}; १४; १५; ३३, ७; ३४, ३; १२; ३५, २; ११^{२}; ३७, ६^{२}; ४०, ६; ४२, ९; ४७, १०; ४८, ३; ५०, ११; ५१, ८; ५४, ८; ११^{२}; ५७, ५; ६०, २; ६१, ४; १४^{२}; ६२, ३; ७०, २–४; ७१, ८; ७२, ६^{२}; ७३, ७^{२}; ८; १०; ७४, १; ६; ७६, ४^{२}; ७७, २; ४; ८०, १३; १४; ८४, २^{२}; ५; २०; ८६, ४; ८८, ४; ९१, ६; ९२, १३^{२}; ९४, ५; १४; ९६, १^{२}; २; ७^{६}; ९७, २; ३; १००, १; १५; १८; १०१, ६^{२}; १०२, १^{२}; ७; १०; १०३, २; ७; १०९, ६; ११२, ६; २३; २४; ११३, १०; ११४, २^{२}; ६; १०^{३}; ११५, १; ११६, ११; १८^{२}; १२०, ४^{२}; ९^{२}; १२; १२३, १२^{२}; १३; १२४, १२; १३^{२}; १२५, ४^{४}; १२७, ८; १२८, ५; १२९, १; १३२, ४^{२}; १३५, ४; ७^{२}; १३६, २; ७; १३९, ३; ८^{२}; १४०, ६; १२^{२}; १३; १४१, ११; १३^{२}; १५३, ४; १५५, १; ६; १५६, १; ४; १५७, ५^{२}; १५९, ३^{२}; १६०, २; ३; १६२, ६; १२; १४^{३}; १६३, १३; १६४, ११; १९; २२; ३१^{२}; ५१^{२}; १६५, १२; १६६, ३; १६७, १०; १६८, ३^{२}; १६९, ४; १७४, १; ३; १७८, २; ३; १८०, २; १८३, ३; १८४, २; ५; १८५, १०; १८६, ३; ११^{२}; १८८, ५^{२}; १८९, २; १९०, ३; ४; ७; १९१, ८; **२.** १; २^{२}; १५^{२}; १६^{२}; २, १२; १३^{२}; ५, ७; ६, ८^{२}; ७, २; ११, ३; १४; १३, ६^{२}; ७^{३}; ८; १२^{२}; १४, ४; १५, २; ९; १९, १; २; ६; २०, ३^{२}; ४; ७; २३, ३; १९; २३, २; १४; १६; २५, २^{२}; २७, १०^{२}; १२; २९, २^{३}; ३; ३१, ५; ३२, ३; ३३, १३^{२}; ३५, ६; ८; ३६, ४; ४१, ११; १९; ४२, १; ४३, १^{२}; **३.** १, १०^{२}; १५^{२}; २, १; ३, ४; ६–८; ६, ३; ९; ९, ९^{२}; १२, ८; १४, ४; १५, ३^{२}; १७, ५^{२}; १९, ३; २०, ३; ५^{३}; २२, ३; २५, ४; ३०, १८; २०; ३१, १९; २१; ३४, ८; ३७, १; ७; ४०, ८; ९; ४२, ७; ४३, ४; ४६, २^{२}; ५२, २; ३^{२}; ५३, ३–५; २०^{२}; ५४, ११; ५५, ११^{२}; १२^{२}; १९; २१; ५७, ५; ५८, ७; ६०, ४; ६; ६२, ९; १४; **४.** १, १७; २, २; ३^{२}; ११^{२}; ९, ५; १६, १९; १७, ११; १८, ४; १९, ८; २०, २; २२, १; ३; ४; २६, १; ७; २८, ५; २९, ३; ३०, १९; ३२, १६^{२}; ३४, ६; १०; ३५, २; ३६, १; ३७, ६; ३८, ५^{२}; ४१, ६; ४२, ३; ४७, २; ३; ४९, १; ३; ५०, १०; ५१, ११^{२}; ५३, ७; ५४, ३^{२}; **५.** ३, ५; ४, ४; ७, १; ९, ६; १०, ३; ६^{२}; ७; ११, ५; १५, ४; १६, ५; २५, ३; २६, १; २७, २^{२}; २८, २; २९, ६; ३०, ३; ३३, ५^{२}; ६; ३७, ३; ३८, ३^{२}; ४०, ७; ४१, १४; १५; ४३, १०; ४४, ३^{२}; १२; ४८, ३; ४९, १; २; ५०, २; ५१, १४^{२}; ५२, ३; ४; ५५, ८^{२}; ६०, ७; ६२, ८; ६४, ४; ५^{२}; ६; ६५, ६; ६६, ६; ६८, २^{२}; ७२, ३^{२}; ७७, २; ७८, ५; ६^{२}; ८२, ९; ८३, ९; ८७, २; **६.** १, ९; ११; ८, ७^{२}; ९,' १^{२}; १०, ५^{३}; १५, ८^{२}; १६, ३; १७; २२^{२}; २३; १७, १४^{२}; १८, ८–१०; २१, ९; २२, ८; २४, ५^{२}; ७; १०; २५, १; २८, २; ३^{२}; २९, ६; ३१, १; ५; ३२, ४; ३३, ३; ५; ३४, १^{३}; ५; ३६, २; ३७, ४; ३८, ३^{९}; ४; ५; ४३, २; ४४, १७; ४५, ४; ४६, ७; ८; ९^{२}; १२; ४७, २; १०; २१; ४८, १; ८; १०; १३^{२}; ४९, १३; १५; ५०, १; ६; ११; ५१, २^{२}; ५२, १४; १५; ५४, २; ५६, ५; ६^{२}; ५७, ५; ६०, १२; ६१, १४; ६३, ८^{२}; ९; ६५, ५; ६६, २; ६८, ४^{३}; ५; ६९, १; ८; ७०, ५; ६^{२}; ७१, २^{२}; ७२, १; ७५, ५; ११^{२}; १९; **७.** ३, ७; १०; ४, १; ५^{३}; ७, ५; १५, ८; ११; १२^{२}; १६, ५; ६; ९^{२}; १७, ४; १८, ६; १०; ११^{२}; १४; १९^{३}; १९, ४; ५^{२}; १०^{२}; २०, १०; २२, ९; २४, १^{२}; २५,

३; ३०, ४; ३१, ५; ६; ३२, ६; २४; ३३, ६; ३६, २; ५; ७; ४०, २^{३}; ६; ४२, २; ४५, १^{२}; ५०, २; ४; ५१, ३^{३}; ५२, ३; ५५, ६^{२}; ५९, १; ६^{२}; ६०, २^{२}; ६२, २; ६४, ४; ६५, २^{२}; ६६, ९; ११; १३; १७; १८; ६७, १०; ६८, १; ७२, ३; ४; ७७, ५^{२}; ७८, ५; ८१, २; ८३, १^{२}; ६^{२}; ८६, १; ८८, ३; ८९, ५; ९१, २^{३}; ९२, ३; ९६, ३; ९७, १; १०; ९९, ५^{२}; १०१, ६; १०४, १०; ११^{२}; १२^{२}; २५; **८.** १, १; ३; ६; १४; २२^{२}; २, ४; २९; ३०^{२}; ३३; ४, ११; ५, १२; ६, १२; १८; २८; ११, १०^{३}; १३, २५; १४, ९; १५, ३; ५; ८; १६, २; १२^{३}; १८, १५^{२}; १९, २३^{२}; २०, १८; २१, ६; १२; २३, ३; २४, १२; २०; २९; २५, २; २७, २; ३०, २^{२}; ३१, १^{२}; ५; ३३, १३; ३४, १५; १६; ३५, १; १०^{६}; ११^{५}; १२^{५}; ३७, ५^{२}; ३९, ४^{२}; ५; ९^{२}; ४१, २; ४५, २५; ४७, ४; ९; १२^{२}; १४^{२}; १६^{२}; १८; ४८, २; ५३, १; ४^{२}; ६०, ७; ११; ६१, १; ८; १७^{३}; ६२, ११^{२}; ६३, २; ६; ६८, ४; ६९, ७; ७१, १५; ७४, १०; ७८, १; ८; ७९, ५; ८०, १०; ८१, ९; ८२, १; ४; ८३, २; ८९, ६; ९१, ६; ९३, २; ४; १०; १३; १७; ९४, ८; ९७, १; १०; १३; १४; १००, २; **९.** १, १०; ४, १^{२}; २; १९, २; २३, ७; ३२, ६^{२}; ४७, २; ५५, १; ५८, ४; ६१, ९; ६३, २; ६५, १०; ६६, १९; ६७, २१; २५; ७०, ३^{२}; ७२, ८; ७४, ५^{२}; ७८, ५^{२}; ७९, १; ८१, २; ८६, ९^{२}; २९^{२}; ४२^{२}; ८९, १; ९५, ३^{३}; ५; ९७, १८^{२}; ४२; ४३; ४४^{३}; ५४; ९८, १०; १२; ९९, ३; १००, ३; ५; ९^{२}; १०६, ३; १०७, २४; २५; १०९, २; ५; ११०, ९; १११, ३; ११३, १०^{२}; ११^{२}; ११४, ४; **१०.** ३, ७; ४, ७^{२}; ५, ७^{३}; ७, ७; ८, ६; ९, ३; १०, ४; १३; ११, २; ८; १४, ३^{२}; ७; ९; ११^{२}; १५, ३^{२}; १३^{३}; १६, ३^{२}; ६; ७; ११; १७, ६^{२}; ११; १३; १९, ७; २०, ८; २२, ६^{२}; १५; २३, ७^{२}; २५, ११; २६, ४^{२}; ६^{२}; २७, १०; २०; २२; २९, ५; ७; ३०, ५; ६; १२^{२}; ३२, ९; ३४, ५; ११; ३६, २^{२}; ३७, २^{२}; ४; ९^{२}; ३८, ४; ३९, १०; ४०, ९; ४८, ३; ४९, २^{३}; ४; ८; ५०, १; ४; ५; ७^{२}; ५१, ८^{४}; ९; ५४, ३^{२}; ५; ५७, ३; ५८, १२^{२}; ६१, २३; २४^{२}; ६२, १०; ६३, ८; ६४, १४; १६; ६७, ३; ७४, ३^{२}; ७७, ८; ८२, ७; ८३, ३; ८४, ७; ८५, १७; ४१^{२}; ८६, २०^{२}; ८७, ३; ८८, १५; १७; ९०, २; ३; ७; ८; १०; १३^{२}; ९१, ३^{२}; ५; ६^{२}; ९२, ३; ७; ९३, ९; १५^{२}; ९७, १; १०; १५; २०; २१^{२}; १००, ६; १०१, ३; १०४, ८^{२}; १०७, ४; ८; १०८, ३; ९–११; १०९, ३; ११०, १–३; ११३, ९^{२}; ११४, ५; ६^{२}; ११५, १; ९^{२}; ११६, ७; ९; १२०, २^{२}; ७; ९^{२}; १२१, ५; ९; १२४, ५; १२६, २; १३३, ५; १३६, ५; १३८, १; १३९, २; १४१, ३; ५; ६; १४२, ८; १४६, ५; १४८, १; १५७, १^{२}; २^{३}; १५८, ४^{२}; १५९, ६; १६१, ५; १६५, ३^{२}; १६७, ४; १७३, ५^{२}; १८१, १^{३}; १८९, १; १९०, १^{२}; ३^{२}.

चकनंत **१.** १६९, ४.

चकमानः **५.** ३६, १.

चकमानाय **१०.** ११७, २.

चकर **१.** १६५, ८.

चकरं **४.** ४२, ६.

चकर्त **१०.** ६७, ६; ७९, ६.

चकर्तिथ **१.** ५७, ६.

चकर्थ **१.** ६९, ४; ११३, ९; १३१, ५; **२.** १३, ११; **४.** ३०, ८; ३२, ११; **५.** २९, १३; ३१, ६; ३३, ४; **८.** १००, ६; **१०.** ५४, ४; १०४, ९; ११२, ५; ११६, ३.

चकर्थ **१.** ५९, ५; १०३, ७; १६५, ७; **३.** १, १; ३०, १७; **५.** ३१, २; **७.** ९८, ३; **१०.** ७३, ७; ८; ७९, ६.

चकानः **३.** ५, २; **५.** ३, १०; २७, ३; **६.** ३६, ५; **७.** २७, १; **१०.** ६४, १६; १२३, ८; १४८, ३.

चकाना **६.** ६८, ३.

चकानाः **२.** ३१, ७; **४.** १६, १५; **६.** २९, १; **१०.** ७७, ८.

चकार **१.** २४, ८; ३२, १; ८०, १; १६४, २९; ३२; **२.** २४, ५; **३.** ३१, २; **४.** १६, १६; **६.** २१, ४; ७३, २; **७.** ६, ४; ५; २६, ३; ८७, १; ९८, ५; **८.** ७०, ३; ९६, २; **१०.** ८६, ३.

चकार **१.** ११६, १६; १९१, १०–१३; **२.** १५, २–९; **३.** ३४, ७; **४.** १६, ४; **५.** ३२, ७; ४५, ७; **६.** २१, ३; २७, १; २; ३९, ३; **७.** ६, ३; १८, १७; ८८, ४; १००, ४; **८.** २, ३४; **९.** ९७, ४१; **१०.** ६८, १०.

चकृपंत **४.** १, १४.

चकृम **१.** ३१, १८; १७९, ५; १८५, ८; **२.** ५, ८; २७, १४; **४.** २, १४; ३, २; १२, ४; १७, १८; ५४, ३; **५.** ८५, ७; **७.** ३१, २; ८६, ५; **८.** ४६, २५; **१०.** १०, ४; ३७, १२; ७०, ८.

चकृम **१.** ७६, ३; १०१, ८; ९; १६२, ७; १७१, ४; **३.** १, २; ५२, ७; ५८, २; **८.** ६१, ८; **१०.** १२, ५; १५, ४; १००, ७.

चकृऽवांसः **१.** १६१, ४; **५.** ४३, ३.

चकृऽवांसं **६.** १७, १३.

चकृऽवान् **५.** २९, १४; **१०.** १३८, ३.

चकृपे **१.** ५२, १२; **४.** ३५, ७; **६.** २३, ६; **८.** ६३, ८; ७७, ७; **९.** ८८, १.

चकृपे **१.** ५२, १४; ११३, ९; **५.** ३०, ४; **१०.** ८, ६.

चक्रे १. २५, १९; ११७, २२; ३. ३, ३; १०; ६२, ५; ८. ६४, ८; १०. ४०, ७.
चक्र १. ८९, ९.
चक्र ४. ३६, ४; ७. ५६, २२.
चक्रतुः १. १५९, २.
चक्रथुंः १. ९२, १७; १०८, ५; १६४, १९; ४. ५७, ५; ६. ५९, १; ७. ८२, ५.
चक्रथुः १. ९३, ६; ११६, ९; २२; ११७, १३; १७; २१; ११८, ६; १८२, ५; ६. ७२, १; ७. ९९, ४; १०. ३९, ७; ९.
चक्रदुः ९. ६४, ३; १०७, २२.
चक्रदत् ८. ७, २६; ९. ७, ३; ७४, १; ८६, ३१.
चक्रन् १०. ९५, १२; १३.
चक्रं १. ३०, १९; १२१, १३; १३०, ९; १५५, ६; १६४, २; ११; १४; ४८; १७४, ५; १७५, ४; २. ११,२०; ४. १, ३; १६, १२; १७, १४; २८, २; ३०, ४; ३१, ४; ५. २९, १०; ३१, ११; ३६, ३; ७३, ३; ६. ३१, ३; ५४, ३; ५६, ३; ७. ६३, २; ८. ५, ३४; ६, ३८; २२, ४; १०. ६१, १६; ७३, ९; ८५, १५; १६; ९३, ९.
चक्रंमंत २. १९, २.
चक्रमंत ४. २२, ६.
चक्रमाणा ६. ६२, २.
चक्रमाणाः १०. १२३, ३.
चक्रमाथे इति ६. ६९, ५.
चक्रंऽआसजः ५. ३४, ६.
चक्रंऽइव २. ५, ३; ३. ६१, २.
चक्रमुः १०. ७५, १.
चक्रमुः १०. ५६, ५.
चक्रमे १. २२, १७; १८; ५. ४७, ३; ८७, ४; ७. १००, ३; ४; ८. २९, ७; १०. ११७, ८.
चक्रंये १. ९, २.
चक्रवाकाऽइव २. ३९, ३.
चक्रस्यं ८. ६३, ८.
चक्रा १. ३४, ९; १६६, ९; १८०, ४; ८. ५, २९; १०. १०, ७; ८; ८९, २; ११७, ५.
चक्राऽइव ४. ३०, २.
चक्राणः १. ७२, १; ८. १४, ५; ९. ४४, ४.
चक्राणाः ८. ७, २३.
चक्रणासंः १. ३३, ८.
चक्राणि ४. ३१, ६.
चक्राणौ ४. ४१, १०.
चक्राते इति ३. ५४, ६; ५५, ११; ८. २६, १३; २९, ९.
चक्राथे इति १. १०८, ३.
चक्राम ८. २१, २.
चर्किः ३. १६, ४[२]; ७. २०, १; ९. ७७, ५; ८८, ४.
चर्कि १. ९, २.
चक्रियां २. २४, ९; १४; १०. ८९, ४.
चक्रियांऽइव १. १८५, १; ५. ३०, ८.
चक्रियाः ८. ४५, १८.
चक्रिरे १. ४०, ५; ८५, १; ९. ७८, ४; १०. १५१, ३; १५४, २.
चक्रिरे १. ३६, ८; ८५, २; ७; १०; २. १, १३; ५. ८, ६; ५८, ७; ६०, ४; ७. ६०, ११; ८. १९, १८.
चक्रुः १. ७१, २; ७३, ७; ४. ३३, ३; ६; ८; १०; ३४, ९; ६. २१, ११; ७. ६३, ५; ९. ९६, ११; १०. ३९, १२; १६९, २.
चक्रुः १. ६७, ५; ६८, ३; ३. २७, ६; ३१, १२; ४. १६, ३; ७. १८, ६; १०; ९१, ३; १०. ६५, ७; १३०, २.
चक्रुषे १०. १३७, १.
चक्रुषे ७. ८७, ७.
चक्रे १. २५, १५; १६४, १३; १६५, १४; २. ४०, ४; ४. ४, ४; ४१, २; ५. ३०, ९; ६. ४, ४; ८. ४१, ६; १०; १०. १०५, ७.
चक्रे १. ३३, १०; २. १०, २; ३. ५, ६; २७, ९; ३२, १३; ४८, ३; ४; ५. २९, ११; ८०, ३; ७. ६, ५; ८७,५; १०१, ३; ८. ४, ५; ९. ७०, १; ७३, १; १०. ६८, ५; ९०, ८; १२३, ८; १८१, २.
चक्रे इति १०. ८५, ११; १२; १६.
चक्रेणं १. ५३, ९; ८. ९६, ९.
चक्रैः ६. ६२, १०.
चक्र्योः १. ३०, १४; ६. २४, ३.
चक्षंणं १.१३, ५; १०५, ६; ५. ५५,४.
चक्षणिः ६. ४, २.
चक्षत १. १२१, २; ९. ७१, ९.
चक्षंते १. १९०, ६.
चक्षते १. १६४, ४४; ८. ४, १३; ४५, १६; १०१, ६; १०. १०७, ४; १७७, १.
चक्षदानः १. ११७, १८.
चक्षदानं १. ११६, १६.
चक्षदे १०. ७९, ७.
चक्षमीथाः २. ३३, ७.
चक्षय १. १२४, ३; ८. ४८, ६.
चक्षंसा १. ५०, ६; ८७, ५; ९२, ११; ९६, २; ११३, ९; ६. ७, ६; ७. ७९, १; ९१, ४; ९८, ६; ८. २५, ९; ९७, १२; ९. १०, ९; ८९, ३; १०. ३७,१०; १२३,८; १३०,६.
चक्षंसि ९. १७, ६.
चक्षंसे १. ७, ३; ४८, ८; ११२, ८; ५. १५, ४; ७. ६६, १४; ८१, १; ८. १३, ३०; ९. १०७, ३; १०. ९, १; ३७, १.
चक्षसे ५. ३, ९.
चक्षाणः १. १२८, ३; ९. ५७, २.
चक्षाणाः १०. ७४, २.
चक्षाथे इति ५. ६२, ८; ७. ७०, ५.
चक्षि ७. ३, ६; ९. ९७, ३३.
चक्षुंः १. २२, २०; ९२, ९; ११५, १; ११८, ७; १३६, २; १६४, १४; ३. २६, ७; ३७, २; ४. २, १९; ५. ८, ६; ४०, ८; ५९, ३; ५; ६. ९, ६; ११, ५; ५१, १; ७. ६१, १; ६३, १; ६६, १६; ७६, १; ७७, ३; ९. १०, ८; १०. ८, ५; १०, ९; १६, ३; ५९, ६; ७३, ११; ८५, ७; ८७, १२; १०२, १२; १५८, ३[३]; ४[२]; १६१, ५; १६४, २.
चक्षुः १०. ९२, १५.
चक्षुंःऽइव ५. ५४, ६.

चक्षुंषः १०. ८२, १; १०२, १२.
चक्षुंषा २. ३९, ५; ८. ५५, ५; १०. ८७, ९.
चक्षुंषे १०. ८७, ८; १५८, ४.
चक्षुंषेऽचक्षुषे १०. ३७, ८.
चक्षुंष्मते १०. १८, १.
चक्षूंषिऽइव ५. १, ४.
चक्षे १०. ७९, ५.
चक्षोः १०. ९०, १३.
चक्ष्व ७. १०४, २५[२]; १०. १६४, १.
चख्यथुः ७. ७०, ४.
चख्वांसं २. १४, ४.
चंक्रमत ८. ५५, ४.
चचक्ष ५. २, ८.
चचरा १०. १०६, ८.
चच्छद्यात् १०. ७३, ९.
चच्छंद ७. ६३, ३.
चतंतं १. ६५, १; १०. ४६, २.
चतसृऽभिः ८. ६०, ९.
चतंस्रः १. ६२, ६; १६४, ४२; १८२, ६; ५. ३५, २; ७. ३५, ८; ८. १००, १०; ९. ७४, ६; ८९, ५; १०. १९, ८; ५१, ९; ५८, ४; ९५, १६; १२८, १.
चतिनं ६. १९, ४.
चतुःऽअक्षः १. ३१, १३.
चतुःऽअक्षौ १०. १४, १०; ११.
चतुःऽअंगः १०. ९२, ११.
चतुःऽअनीकः ५. ४८, ५.
चतुःऽअश्रिः १. १५२, २.
चतुःऽअश्रिं ४. २२, २.
चतुःऽकपर्दा १०. ११४, ३.
चतुःऽत्रिंशत् १. १६२, १८.
चतुःऽत्रिंशता १०. ५५, ३.
चतुःऽदश १०. ११४, ७.
चतुःऽधा ४. ३५, २; ३.
चतुःऽपत् १. ४९, ३; ९४, ५; १२४, १; १०. ९७, २०.
चतुःऽपदः ६. ७१, २; १०. १२१, ३.
चतुःऽपदा १. १६४, २४.
चतुःऽपदी १. १६४, ४१.
चतुःऽपदीं १०. १३, ३.
चतुःऽपदे १. ११४, १; १२१, ३; १५७, ३; ३. ६२, १४; ५. ८१, २; ६. ७४, १; ७. ५४, १; ९. ६९, ७; १०. ३७, ११; १६५, १.
चतुःऽपात् ४. ५१, ५; १०. २७, १०; ९९, १०; ११७, ८.
चतुःऽपादः ८. २७, १२.
चतुःऽभिः १. १५५, ६; २. १८, ४.
चतुःऽभृष्टिं १०. ५८, ३.
चतुःऽयुगः २. १८, १.
चतुःऽयुजः ८. ६, ४८.
चतुःऽवयं १. ११०, ३; ४. ३६, ४.
चतुःऽशतं ८. ५५, ३.
चतुःऽशृंगः ४. ५८, २.
चतुःऽसमुद्रं १०. ४७, २.
चतुःऽसहस्रं ५. ३०, १५.
चतुरः १. २०, ६; ४१, ९; १६१, २; ४; ४. ३३, ५; ६; ३५, ४; ९. ३३, ६; १०. ११४, ६.
चतुर्णां ८. ७४, १३.
चत्ता १०. १५५, २.
चत्तार्य १. १३२, ६.
चत्तो इति १०. १५५, २.
चत्वारः १. १२२, १५; ५. ४७, ४; ७. १८, २३; ८. ७४, १४.
चत्वारि १. १६४, ४५; ४. ५८, ३; ५. ३०, १२; १४; ८. २, ४१; ९. ७०, १; १०. ५४, ४.
चत्वारिंशत् १. १२६, ४.
चत्वारिंशता २. १८, ५.
चत्वारिंश्यां २. १२, ११.
चन १. १८, ७; २४, ६; ५५, १; ५; ७४, ७; ८१, ५; ८४, २०; १००, १५; १०५, ३; ११३, ८; १३६, १; १३९, २; ५[२]; १५०, २; १५२, २; १५५, ५; १६६, १२; १९१, ७; २. १६, २; ३; २३, ५; २४, १२; २८, ६; ३. ३०, १; ३६, ४; ४. १८, ८; ९; ३०, ३; ३१, ९; ५. ३४, ५; ७; ४१, १३; ४२; ६; ८२, २; ६. ३, २; २०, ४; २६, ७; ४७, १; ३; ४८, १७; ५४, ९; ५९, ४; ६९, ८; ७५, १६; ७. १८, ९; ३२, १; १३; १९; ५९, ३; ८२, ७; ८३, २; ८६, ६; १०४, ३; ८. १, ५; २, १४; १९, ६; २३, १५; २४, १५; २८, ४; ४७, ७; ५१, ७; ५२, ७; ५५, ५; ६४, २; ६६, १३; ६८, १९; ७८, १०; ९१, ३[२]; ९. ६१, २७; ६९, ६; ११४, ४; १०. ३३, ९; ३९, ११; ४८, ५; ४९, ५; १०; ५६, ४; ५९, ८; ६२, ९; ८५, ३; ८६, ११; ९५, १; ११२, ९; ११९, ६; ७; १२८, ४; १२९, २; १५२, १; १६८, ३; १८५, २.
चनः १. ३, ६; २६, १०; १०७, ३; २. ३१, ६; ३५, १; ६. ४, २; १०, ६; ४९, १४; ७. ३८, ३; ८. १९, ११; ३२, ६; १०. ११६, ८.
चनःऽहितः ३. २, २; ७; ११, २; ९. ७५, १; ४.
चनस्यतं १. ३, १.
चनिश्चदत् ५. ४३, ४.
चनिष्टं ७. ७०, ४.
चनिष्ठत् ८. ७४, ११.
चनिष्ठं ५. ७७, ४.
चनिष्ठया ९. ९, २.
चनिष्ठा ७. ५७, ४; ७०, २; ५; ८. ७४, ८.
चनिष्ठाः ७. २०, ८.
चनिस्कदत् ८. ६९, ९.
चंद्र ६. ६, ७.
चंद्र ५. १०, ४.
चंद्रऽअग्राः ५. ४१, १४; ६. ४९, ८.
चंद्रः १. १५०, ३; ८. ४, ९.
चंद्रऽनिर्णिक् १०. १०६, ८.
चंद्रऽबुध्नः १. ५२, ३.
चंद्रं ३. ३, ५; ३१, १५; ४. २, १३; ६. ६, ७; ८. ६५, ११; १०. ८५, ३१; १०७, ७.
चंद्रमसः १. ८४, १५.
चंद्रमसा १०. ६४, ३.
चंद्रमाः १. २४, १०; १०५, १; १०. ८५, १९; ९०, १३.
चंद्रमाःऽइव ८. ८२, ८.
चंद्रंऽइव २. २, ४.
चंद्रऽरथः १. १४१, १२.

चंद्रऽरथं ३. ३, ५.
चंद्रऽरथा ३. ६१, २.
चंद्रऽरथाः ६. ६५, २.
चंद्रऽवत् ५. ५७, ७.
चंद्रऽवता ३. ३०, २०.
चंद्रऽवर्णाः १. १६५, १२.
चंद्रा १. १५७, १; ४. २३, ९; ९. ९७, ५०.
चंद्राऽइव ३. ६१, ७.
चंद्राः ७. ३९, ७; ९. ६६, २५; १०. १२१, ९.
चंद्राणि ५. ४२, ३; ९. ६९, १०.
चंद्रान् ८. २०, २०.
चंद्राभिः ६. ६, ७.
चंद्रासः ३. ४०, ४.
चंद्रेण १. ४८, ९; १३५, ४; ४. ४८, १.
चमसः ४. ३५, ४; १०. १६, ८; १०१, ८.
चमसं १. २०, ६; ११०, ३; १६१, १; २; ५; ४. ३५, २; ३; ५; ३६, ४; १०. १६, ८; ६८, ८.
चमसा ४. ३३, ५.
चमसाः १. ५४, ९.
चमसान् १. १६१, ४; ९; ३. ६०, २; ४. ३३, ६.
चमसान्ऽइव १०. २५, ४.
चमसे १०. ९६, ९.
चमसेषु ८. ८२, ७.
चमू इति ५. ५१, ४; ८. ४, ४; ७६, १०; ९. ४६, ३; १०७, १८; १०. २४, १.
चमूषु ३. ४८, ४; ८. ८२, ७; ८; ९. २०, ६; ६२, १६; ६३, २; ९२, २; ९३, ३; ९७, २१; ३७; ४६; ९९, ६; ८.
चमूऽसत् ९. ९६, १९.
चमूऽसदः १. १४, ४; ५४, ९; ९. ८, २; ७८, २; १०. ४३, ४.
चम्रिषः १. ५६, १.
चम्रीषः १. १००, १२.
चम्वः ८. २, ८.
चम्वा ३. ५५, २०.
चम्विऽइव १०. ९१, १५.
चम्वोः १. २८, ९; १६४, ३३; ४. १८, ३; ६. ५७, २; ९. ३६, १; ६९, ५; ७१, १; ७२, ५; ८६, ४७; ९६, २०; २१; ९७, २; ४८; १०३, ४; १०७, १०; १०८, १०.
चयत् ५. ६०, १.
चयते १. १६७, ८.
चयते ९. ४७, २.
चयध्वे ६. ५१, ७; ७. ५२, २.
चयमानाः २. २७, ४.
चयसे १. १९०, ५.
चयिष्टं ६. ६७, ८.
चयेम १. १३२, १.
चर १. १०, ३; ९१, १९; ११४, ३; १८७; ३; ७. ३१, १०; ४६, २; ८. २५, २१; ३२, ९१; ४८, ६; ९. ८२, ४; १०. १६४, १.
चरः ८. १, २८.
चरचरः १०. ८५, ११.
चरणं ३. ५, ५; ९. ११३, ९.
चरणीनां ८. २४, २३.
चरणीयमाना ३. ६१, ३.
चरणे १०. १३६, ६; १३९, ६.
चरण्युः १०. ९५, ६.
चरत् ३. ४४, ३; ५४, ८; ६. ५९, ६; १०. १२३, ५.
चरत् १. १७३, ३; १०. ८०, १.
चरत १०. ३४, १४.
चरतः १. १४६, १; ६. २७, ७; १०. ५, ३; ३४, १०.
चरतः १. ६२, ८; ९५, १; १०२, २; ११३, २; ३; १४६, ३; २. २४, ५; ८. २९, ८; १०. १२, ७; १४, १२; २७, १७; ८५, १८.
चरता ३. ३२, ६.
चरतां २. ३८, ६.
चरति ३. ५५, ७; ४. ३८, ४; ६. ६१, ८; ७. ४६, ३; ५५, ६; ८. ३९, १; १०. ४, ४; १६, ५; ८८, ६.
चरति १. ५२, ६; ९५, ४; १०; ११३, १३; १४५, ४; १६४, ३०; १८१, ६; ३. ७, २; ३०, १४; ३८, ४; ५४, २; ५५, ६; ८; ९; ५८, १; ५. ४४, ८; ६३, ४; ६. ९, ६; २१, ४; १०. १७, ६; ७१, ५; १०१, ११; १०९, ५; १६८, ४; १८९, २.
चरते १०. ११७, ३.
चरथं १. ५८, ५; ६८, १; ७२, ६; ३. ३१, १५; ८. ३३, ८; १०. ९२, १३.
चरथा १. ७०, २.
चरथाय १. ३६, १४; ४. १८, १०; ३६, ३; ५१, ५; १०. ३९, ४.
चरध्यै १. ६१, १२.
चरन् १. ३३, ४; १४४, ४; ६. ९, ३; ८. ४५, ३८; ७२, ५; १०. ११५, १; १३६, ६.
चरंत ३. ४, ५.
चरंतं १. ६, १; १६४, ३१; १८५, २; ३. १, ९; ४. १८, १२; ५. २, ४; ७. १०४, ८; ८. ९६, १४; १०. ५२, ४; ८७, ६; ८८, १६; १२४, ९; १३५, २; १७९, २.
चरंता १. १५८, २.
चरंति ४. ६, १०; ५१, ६; ५. ९, २; ३१, १२; ४७, ५; ६. ४७, ३१; ५८, ३; ७. ३, ३; ८. २०, १८; ६०, २; ९. ४१, ३; १०. १०, ८; ७१, ९.
चरंति १. ३२, १०; ३६, ३; ९४, ५; १२७, ९; १६३, ११; ३. ५७, ३; ४. ५१, ८; ९; ५. १, ४; ४७, ४; ६३, २; ५; ६. ६, ३; २८, ४; ७. १, १५; ३३, ९; ९. १०७, १९; १०. १, ४; ४७, ७; ५९, ९; ७१, ८; ८२, ७; ११४, १०; ११६, ९; १४२, २.
चरंती १. १६७, ३; ७. ३६, ७.
चरंतीः १. २४, ६; ३. ३३, ४; १०. २७, ८; ३०, १०.
चरंतीं ३. ५७, १.
चरंतु ४. ८, ७; ८. २५, ६; १०. ३५, ६.
चरमः ८. २०, १४.
चरमं ७. ५९, ३; ८. ६१, १५.
चरंसि ३. ३०, ४.

चरसि ३. ६१, १; ८. ३३, ८; १०. ४, २.
चरसे १. ९२, ९; ५. ४७, ४.
चराणि ५. २९, १३.
चरार्था १. ६६, ५.
चरान् ८. ९२, ३३.
चरामसि १. ५७, ४; ७. ८९, ५; ८. ६१, ५; १०. १६४, ४.
चरामसि ८. २५, १६; ९. १, ५; १०. १३४, ७.
चरामि १. १६४, ३७; ३. ५५, १४; १०. ९५, १६; १०८, २; १२५, १.
चरायै ७. ७७, १.
चरात्र ७. ८८, ३.
चरितवे १. ११३, ५.
चरितस्य १. ११०, २.
चरित्रं १. ११६, १५.
चरित्रात् ८. ४८, ५.
चरित्रैः १०. ११७, ७.
चरिष्णु ४. ७, ९; १०. ५९, ९; ८८, १३.
चरिष्णुः ६. ६१, ८.
चरिष्णुऽधूमं ८. २३, १.
चरिष्णू इति १०. ८८, ११.
चरिष्ण्वं ८. १, २८.
चरुः ७. १०४, २; ९. ५२, ३.
चरुं १. ७, ६; १०. ८६, १८.
चरूणां १. १६२, १३.
चरेत् ४. ४, ९.
चरेते इति १. १२३, ७; ३. ७, १.
चरेम ४. ५७, ३; ५. ५१, १५.
चरौ १०. १६७, ४.
चर्कर्मि ४. २९, २.
चर्किरन् १. १३१, ५; ८. ५५, ५; १०. ९२, ३.
चर्किराम ४. ३९, १; ४०, १.
चर्कृतात् १. १०४, ५.
चर्कृतिः ५. ७४, ९; ६. ४८, २१.
चर्कृत्यः १०. ५०, २.
चर्कृत्यं १. ६४, १४; ११९, १०; ४. ३८, २; ८. २४, २३; १०. ३९, १०; ४७, २.
चर्कृत्यानि ८. १०३, ३.
चर्कृपत् १. १७६, २; ८. २०, १९.
चर्कृपत् १. २३, १५.
चर्कृपे १०. २२, १; १०५, ४.
चर्कृपे १०. ७४, १.
चर्चरं १०. १०६, ७.
चर्चूर्यमाणं १०. १२४, ९.
चर्म ३. ५, ६; ५. ८५, १.
चर्मऽइव १. ८५, ५; ४. १३, ४; ७. ६३, १; ८. ६, ५.
चर्मणः १. ११०, ८; १६१, ७; ३. ६०, २; ४. ३६, ४.
चर्मणी इवेति चर्मणीऽइव ६. ८, ३.
चर्मन् ४. ५, ७.
चर्मऽम्नाः ८. ५, ३८.
चर्माणि ८. ५५, ३.
चर्षणयः १. १८४, ४; ६. २, २; २५, ७; ३१, १; ३३, २; ८. २, ३३; १६, ६; ९.
चर्षणिः १. ४६, ४.
चर्षणिऽधृत् ४. १७, २०; ८. ९६, २०; १०. ८९, १.
चर्षणिऽधृतः ३. ३७, ४; ५९, ६.
चर्षणिऽधृतः १. ३, ७.
चर्षणिऽधृतं ३. ५१, १; ४. १, २[२].
चर्षणिऽधृता ८. ९०, ५.
चर्षणिऽप्राः १. १७७, १; १८६, ६; ३. ३४, ७; ४. २, १३; ६. १९, १; ३९, ४; ७. ३१, १०.
चर्षणिऽप्रां ६. ४९, १५.
चर्षणिऽभ्यः १. ५५, १; ८४, २०; १०९, ६; ४. ३७, ८; ६. ३१, ५; ४८, १५; ७२, ५.
चर्षणिऽसहः ८. १९, ३५.
चर्षणिऽसहं १. ११९, १०; ५. ३५, १; ६. ४६, ६; ८. १, २; २१, १०.
चर्षणिऽसहा ७. ९४, ७.
चर्षणिऽसहे ९. २४, ४.
चर्षणी इति १. १०९, ५.
चर्षणीः १. ८६, ५; ३. ४३, २; ४. ७, ४; ५. २३, १; ८६, २; ७. १५, २; ९. १०१, ९.
चर्षणीनां १. ७, ९; १७, २; ३२, १५; ८६, ६; १२७, २; १७६, २; ३. ६, ५; १०, १; ६२, ६; ४. ८, ८; २०, ८; ३१, ४; ५. ३९, ४; ६७, २; ६. १, ८; १८, १; २२, १; ३०, ५; ७. २७, ३; ८. १६, १; २३, ७; ६०, १७; ६४, ४; ६८, ४; ७०, १; ९२, १; ९३, १६; ९६, ४; १८; १०. ९, ५; ९३, ९; १०३, १; १२६, ६; १३४, १; १८०, ३.
चलाचलासः १. १६४, ४८.
चपाले १. १६२, ६.
चपालऽवंतः ३. ८, १०.
चष्टे १. १०८, १; ७. २८, ४; ६०, ३; ६१, १; ८. १९, १६; १०. ३०, २.
चष्टे १. २४, १२; ९८, १; १६४, ४४; १९०, ७; ३. ५५, ९; ५९, १; ५. १९, १; ६. २६, २; ५१, २; ७. ३४, १०; ८. २५, १६; ६२, ६; ९. ३८, ५; १०. ५, १; ३४, १३; ५५, ३; ९२, ६; ११४, ४; १३९, २; ३.
चस्कंद १०. १७, ११.
चाकन् १. ३३, १४; १७४, ५; २. ११, ३; १०. २९, १; ९५, ४; १४८, १; ४.
चाकन् १. १४८, २; १०. १३२, ४.
चाकन १. ५१, ८; १२०, १०.
चाकनः १. ५१, १२; ८. ५२, ४; ६२, ४.
चाकनत् १०. ९१, १२.
चाकनत् ८. ३१, १; १०. १४७, ४.
चाकनंत ५. ३१, १३[२].
चाकनाम २. ११, १३.
चाकंतु १. १२२, १४.
चाकंधि १०. १४७, ३.
चाकन्यात् १०. ३१, ४.
चाकशीति १. १६४, २०.
चाकशीमि ४. ५८, ५; ९.
चाक्लृप्रे १०. १३०, ६.
चाक्लृप्रे १०. १३०, ५.
चाक्ष्मः २. २४, ९.
चातयते ४. १७, ९.

चातयस्व ५. ४, ६.
चातयस्व २. ३३, २; ७. १, ७.
चातयामसि १०. १५५, १.
चार्यमानः ७. १८, ८.
चायमानः ६. २७, ८.
चायमानाः १०. ९४, १४.
चायमानाय ६. २७, ५.
चायवः ३. २४, ४.
चारथे ८. ४६, ३१.
चारवः ५. ५९, ३; ९. ७७, ३; १०. ९४, १०.
चारीत् ७. २५, १.
चारु १. २४, १; २; ५५, ४; ६१, ७; ७२, २; १८७, ६; २. २७, ८; ३५, ११; ३. ५, ६; ३२, १; ५४, १६; १७; ५६, ४; ४. २, १९; ५, ७; १०; ५. ३, ३; ४३, ३; ४८, ५; ७. ९८, २; ९. ३४, ५; ७२, ७; ८६, २१; ९६, १६; ९७, २४; १०९, १४; १०. ३२, ४; ९६, १.
चारुः १. ९४, १३; ९५, ५; १३७, २; २. २, ८; ३. ४९, ३; ४. ६, ६; ४९, २; ५. ३३, ५; ६. ८, १; ७. २२, २; ८. १, २६; ९. १७, ८; ६१, ९; १०९, १३; १०. १, २; २१, ४; ५६, १; १००, ६.
चारुणः ८. ५, १४; ९. ७०, २; ४; १०८, ४; ११०, ४.
चारुऽतमः ५. १, ९.
चारुऽतमं १. ६२, ६.
चारुऽत्वं १०. ७०, ९.
चारुऽप्रतीकः २. ८, २.
चारुं १. १९, १; ५८, ६; ७२, १०; ३. ५२, ५; ५. ७१, १; ७. ८४, ३; ८. ६४, १२; ९. ३०, ६; ४४, ४; ४८, १; १०२, ६; १०. २१, ७; ३९, २; ९१, १४; १४४, ५; १६०, ३.
चारूणि ९. ७०, १.
चारोः ३. ५०, २; ५. ३३, ७; ७. २९, १; ६५, ४.
चाषेण १०. ९७, १३.
चास्कंभ १०. १११, ५.
चिकाय १०. ८९, ३.
चिकाय १०. ११४, ९.
चिकित् ८. ५१, ३; ९७, १४; १०२, २; १०. ३, १.
चिकितः १. ९१, १.
चिकितान ५. ६६, १.
चिकितानः ३. १८, २.
चिकितुः ८. ५६, ५.
चिकितुः ३. ५३, २४; ७. ११, ३.
चिकितुषः १. ७२, ८; १६४, ६; ७. ८६, ३.
चिकितुषा ५. ६१, १३.
चिकितुषी १०. १२५, ३.
चिकितुषे ४. १६, २; ५. ४१, ११; ६. ४१, ४; ६६, १; ७. १०४, १२; ८. १०१, १५.
चिकिते ९. २३, २.
चिकिते १. ५१, ७; ७१, ७; २. ४, ५; २७, ११; ३. ५३, २३; ४. २३, २.
चिकित्रिरे १. १६६, १३; १०. ९२, ४; १०.
चिकित्रे १. १८६, ९.
चिकित्रे १०. ३, ४; ३०, ६; ९१, ४; ५.
चिकित्वः १. ७०, ३; २. ६, ८; ३. १७, ५; २५, १; २९, १६; ५. २, ७; ३, ७; ९; १२, २; ६. ५, ३; १०. ४, ४.
चिकित्वना ८. ६०, १८.
चिकित्वांसः ७. ६०, ७.
चिकित्वांसं ४. ७, ५.
चिकित्वान् १. २५, ११; ६८, ३; ७०, १; ७१, ५; ७; ७२, ४; ७७, ५; १२५, १; १४५, १; १६९, १; ३. ७, ३; ९; १७, २; २९, ३; ८; ४४, २; ४. ३, ८; ५, १२; ८, ४; १२, १; २९, २; ५. २, ५; ६. ५२, १२; ८. ६, २९; ४४, ९; १०. १२, २; ५३, १; ९८, २; ५; ९९, १; ११०, १.
चिकित्वित् ४. ५२, ४.
चिकित्वित्ऽमनसं ५. २२, ३; ८. ९५, ५.
चिकित्स १. ९१, २३; ६. ४७, २०.
चिकित्सत् ४. १६, १०.
चिकित्संती १. १२३, १.
चिकित्सामः ८. ९१, ३.
चिकिद्धि ५. २२ ४.
चिकिद्धि २. ४३, ३; ४. ४, ११; ५. १, १०; १२, २; ८. ३९, ३; १०. २८, ४.
चिकीपते ८. ७८, ६[२].
चिकेत ९. १०२, ४; १०. २६, २.
चिकेत १. ६७, ४; ५. ३३, १; ६५, १; १०. ५५, ६.
चिकेत १. ३५, ७; ९५, ४; १००, १६; १५२, ३; १६४, १६; ४८; २. ४, ६; १४, १०; ५. १९, १; २७, १; ७. ५६, ४; ६१, १; ८. २, १४; १७; ९, ७; ३९, ५; १०. ५१, ४; ५९, ३; ७९, ४.
चिकेतत् १. ३५, ६; ६९, ५; ५. ३६, १; ६. ९, ३; ६२, ९.
चिकेतत् १. १५२, २.
चिकेतति १. ४३, ३; ८२, ४; ८. २६, १४; १०. ३८, ३; १४७, ४.
चिकेतति ५. ७३, ६; ६. ५९, ५; ८. १, ३१.
चिकेतथः ८. ९, ४.
चिकेतं १०. २८, ५.
चिकेतसि १. १३१, ६.
चिकेथे इति ५. ६६, ४.
चिक्यतुः ८. २५, ९.
चिक्युः १. १६४, ३८.
चिक्युः १. १६४, ३८; १०. ११४, २; १२४, ९.
चिक्रदः ९. ९०, ४.
चिक्रदत् ८. ५१, ४.
चिक्षिपः १०. १६, १.
चिच्चिकः १०. १४६, २.
चिच्युषे ४. ३०, २२.
चित् १. ४, ५; ६, ५[२]; ८, ९; १०, ९[२]; २४, ४; ८–१०; २५, १; २६, ६; २७, ८; २८, ५; २९, १; ३०, ४; ३१, २; ६; १३; १४;

३२, ८; ३३, ५; १५; ३४, १; ३७, ११; १३; १५; ३८, ७; ९; ३९, ४; ६; ४०, ८; ४१, १; ९; ४२, ४; ४८, १४; ४९, १; ३; ५१, ३; ६; ९; ५२, ७; १०; ५३, १; ५४, ५^{२}; ५५, १; ५८, १; ५९, ५; ६०, २; ६१, ६; ८; ६२, ९; ६३, १; ५; ६४, ३; ६८, ४; ७०, २; ७१, २; ७२, ३; ८०, ११; १४; ८१, २; ८४, ९; ८५, ४; १०; ८६, ५; ८७, १; २; ९४, ७; ९; १००, ८; ९; १०१, ४; १०४, २; १०५, ७; १०७, १; ११०, २; ३; ११६, ३; २२^{२}; ११७, ७; १२०, २; ६; १२१, १०; १२४, १२; १२५, ७; १२७, ३^{२}; ४^{२}; १२९, १–५; १०^{४}; १३२, ४^{२}; १३३, २; १३५, ९^{२}; १३६, १; १३८, ३; १४०, ११; १४८, ३; १५०, २; १५२, ३; १५६, १–३; १५८, २; १६४, ६; १६५, १०; १६७, २; ७; ९; १६८, ४; १६९, १^{२}; ३; ५; १७३, ५^{२}; ७; ८; ११^{२}; १२; १७६, ४; १७८, २; १७९, २^{२}; ४; १८०, ७^{२}; ८; १८२, ३; १८४, १; १८५, ८; ९; १८७, ७; १९१, १०–१२; **२.** १०, ३; ११, २; ७; १२, ८; १३^{२}; १५; १५, ९; २०, ५; २३, २; ११; २४, ५; २६, ४; २७, ३; ५; ११^{२}; १४; ३०, ४; ८; ३३, १२; ३८, २^{२}; ३^{२}; ४२, १; **३.** १, २; ९; १३; ६, २; ७; १०; ७, १०^{२}; ९, ७; ३०, २; ७; ३१, ९; १२; १६; ३२, १६; ३५, २; १०; ३६, ६; ३९, २; ३; ८; ४५, १; २; ५३, २२^{३}; ५४, ४; ५६, ४; ७^{२}; ५७, १; ५८, ४; ५; **४.** २, ७; १८; ३, ४; १०; १४; ६, १; ७; ७, ९; १०; ८, ३; १०, ५^{२}; ७; ११, १; ६; १२, ४^{२}; ५; ६; १६, ३; ५; ६; १६; १७; २०; १८, १; ८^{२}; २०, ९; २२, १; २३, ७; २८, ५; २९, १; ३०, ९; ३१, २; ८; ३२, २; ३; ४३, ४; ४५, ६; **५.** २, ५; ७; १०; ७, २^{२}; ४; ६; १०; १०, ४; १८, २; २०, १; २५, २^{२}; २९, ४; १२^{२}; १४; ३०, ४^{२}; ५; ८; १५; ३१, २; ७; १०^{२}; ११; ३२, २–५; ६^{२}; ८; ९; ३३, ४^{२}; ३८, ४; ३९, ३; ४१, १३; १७^{२}; ४४, १०; ४९, १; ५२, १२; ५४, ३; ५५, ३; ५६, २; ५८, ७; ६०, २^{२}; ३^{२}; ६५, ४; ६७, ४; ७०, १; ७४, ४; ८; १०; ७५, ७; ७८, ४; ७९, १; ५; ८४, ३; ८६, १; ५; **६.** २, ९; ३, ३; ४; ४, ३; १०, ४; ११, ३; १५, १^{२}; १७, ९^{२}; १८, ८; ११; १९, २; ४; १२; २२, ४; ६; २३, ३; २४, ७; ८^{२}; २७, ४; २८, ५; ६^{२}; ३०, ३^{२}; ३१, २; ३५, ५; ३७, १; ३; ३८, २; ३९, ३; ४४, १५; ४५, २^{२}; ९; ४७, १३; ४८, २१; ४९, ११; १३; ५१, ८; ५३, ३^{२}; ६२, ९; ११; ६५, १; ४; ६६, १; ५^{२}; ७; ६७, ३; ५; १०; ७१, ५; ७३, २; **७.** १, २; २२; ४, २^{२}; ८; ७, १; ८, ५; ११, ३; १८, १; ५; १७^{२}; १८; २०; १९, ९; २०, १; ४–६; २१, ७; ८; २२, ८; २३, ४; २७, ३; ४; २८, १; ३; ३२, १; ५^{२}; ३४, २; ३७, ५; ७; ३८, ३; ४१, २^{३}; ४५, २; ४८, ३; ५३, १; ५६, १५; २०^{२}; २३; ५७, १; ५; ५८, २; ६; ५९, ७; ६०, ६^{२}; ७; ९; १०; ६७, २; ६८, ८^{२}; ६९, २; ७०, २; ५; ८५, ३; ८६, १; ३; ८; ८७, ७; ८८, ५; ९०, ४; ९३, ६; ९४, ११; ९५, ४; ९७, ६; १०; ९९, ४; १०३, ८; १०४, ७; **८.** १, १; ३; ७; १२; २, ३५; ३९; ४, १२; १८; २१; ५, १६; २५; ३०; ३७; ६, ६; ७, १५; ३४^{२}; ८, ६; ७; ११, ४; ७; १५, ६; १६, ८; १८, ५; १२; १३; २२; १९, १५; ३५; २०, १; ५; १८; २१; २२; २१, १; ६; १६; २२, ११; १३; १६; २४, ३; १०; ११; २५, ९^{२}; १५; २६, ५; २७, ९; १८^{३}; ३१, १५; ३२, ११; १२; ३३, १४; १७; १८; ४०, १; २; १०; ४५, ११; १३; १४; १९; ३२; ४६, ११; १६; २१; २५; २७; ५१, ९; ५३, ४; ६०, ७; ६१, ३; ४; १२; ६२, ३; ५; ११; ६४, ५; ६६, ४; ५; ८; १२^{२}; ६७, १७; ६८, ६; १०; ६९, १७; ७०, ७; ७३, २; ५; ७७, ११; ७९, ४; ८०, ४; ८३, ९; ८६, ४; ५; ८९, ४; ९२, १०; २७; २९; ९३, १०; ११; ९६, २; ९८, ८; १००, ५; १०२, १४; २०; १०३, ५; १३^{२}; **९.** ६, ९; १०, ८; २९, ५; ४७, १; ६६, १७^{३}; ६७, ३०; ७२, १; ७३, ९; ७९, २; ८७, ३; ९१, ४; ९७, २७; ३८; ५२^{२}; १०४, ६; १०५, ६; १०७, २; ११०, ५; ६; **१०.** ५, ३; ८, १; ८; ९; १०, १^{२}; ३; ७; ११, ३; १२, ५; १५, ६; २२, ५; २३, २; ४; २५, ३; २७, १२; २०; २८, ६; ९; १०; ३१, २; ३४, ८^{२}; ३९, ३^{६}; १३; ४१, २; ४२, ६; ४५, ६; ५०, २; ६१, १८; २१; ६४, १३; ६७, ११; ६९, ९; १०; ११^{२}; ७३, १–३; ६; ७६, २; ५^{४}; ७७, ६; ९१, १२; ९२, ८^{२}; ९३, ७; ८; ९४, २; ९६, १०^{२}; १०२, ११; १११, २; ४; ५^{२}; ११२, १०; ११५, ६; ११७, २; ४; ९^{४}; १२०, ४; १२१, ८; १२७, ५; १३१, २; १३२, ३; १३३, १; १४३, १; २; १४४, ६; १४७, १; १५०, १; १५४, १; ४; १७१, ४; १७६, ४; १७८, ३.

चितः **१.** ११२, १७; १५८, ४.

चितन **४.** ३७, ७.

चितंत्यो **१.** १२९, ७.

चितयंत् **२.** ३४, ७.

चितयत् **१.** १८०, ८; **२.** २, ५.

चितयत्ऽभिः **५.** ४१, ७.

चितयन् **५.** १५, ५.

चितयन्त २. ३४, २; ४. ५१, ३; १०. ९५, ३.
चितयन्तः १. ३३, ६; ९४, ४; १३१, २; ५. १९, २; ६. १, २.
चितयन्तं २. २, ४; ६. ६, ७.
चितयन्ति ७. ६०, ६.
चितयन्ते १. १७१, ५; ५. ५९, २.
चितयन्त्या ६. १५, ५.
चितयेम ४. ३६, ९.
चितयेम २. २, १०.
चितानाः ९. १०१, ११.
चितासः ७. १८, १०.
चिते १०. १४३, ४.
चित्तः ९. ६५, १२.
चित्तऽगर्भासु ५. ४४, ५.
चित्तं १. १६३, ११; १७०, १; ५. ७, ९; १०. १०३, १२; १२८, ६; १६६, ४; १९१, ३.
चित्तानि ७. ५९, ८.
चित्तिः १. ६७, ५; १०. ८५, ७.
चित्तिऽभिः ३. २, ३; ३, ३; ५. ४४, १०; ८. ४४, १९; ५९, ३.
चित्तिऽभिः १. १६४, २९.
चित्ति २. २१, ६; ४. २, ११.
चित्ती ८. ७९, ४.
चित्र ८. ४६, २०.
चित्र ४. ३२, २; ५. ३९, १; ६. ६, ७; ४६, २; ५; ७. २०, ७; ८. २१, १७; ९७, १५.
चित्रऽआयुः ६. ४९, ७.
चित्रऽऊतयः १०. १४०, ३.
चित्रः ८. २१, १८.
चित्रः १. ४८, ११; ६६, ३; ८८, २; ९४, ५; ११३, १; १६६, ४; १७२, १[२]; २. ८, ४; ३. २९, ६; ४. ३१, १; ६. ४, ६; ४८, ९; ७. ३, ६; ९. ८६, ३४; १०. १, २; १००, १२; ११५, १.
चित्रऽक्षत्र ६. ६, ७.
चित्रऽतमः १. १०८, १; ६. ३८, १.
चित्रऽतमं ४. २३, ६; ६. ६, ७; ९. ६८, १०.
चित्रऽतमा ४. १, ६.
चित्रऽदर्शीकं ६. ४७, ५.
चित्रऽध्रजतिः ६. ३, ५.
चित्रऽबर्हिषं १. २३, १३; १४.
चित्रऽभानवः १. ६४, ७; ८५, ११.
चित्रऽभानुः १. ३५, ४; २. १०, २; ७. ९, ३.
चित्रऽभानुं ७. १२, १; ८. ४४, ६.
चित्रभानो इति चित्रऽभानो ५. २६, २.
चित्रभानो इति चित्रऽभानो १. ३, ४; २७, ६; १०. ५१, ३; ६९, ११.
चित्रं १. ९, ५; ३४, १०; ३७, ३; ४४, १; ७१, १; ९२, ५; १३; ११०, ९; ११३, १५; २०; ११५, १; १३९, ८; १४२, ४; १४८, १; २. १३, १३; ३४, १०; ३. २, १५; ३०, १३; ६१, ६; ४. ७, १; ६; २३, २; ३२, २; ३६, ९; ५. ३, ३; १३, ६; ६३, ४; ८२, ३; ६. ६, ७; १०, ५; ६५, २; ६६, ९; ७. ४५, ४; ६१, ५; ६८, ५; ७४, २; ७५, २; ८१, ५; ८. १३, ५; २१, १; ४६, २७; ६७, ३; ८१, १; ९. ४, १०; १९, १; ६१, १६; १०. २, ६; २१, ४; ३६, १३; ३७, १०; ४७, १; ९९, १; १०६, ९; १०७, १०; ११२, ९.
चित्रऽमघा ७. ७५, ५; ७७, ३; ८. ५८, ३.
चित्रऽमघे १. ४८, १०.
चित्रऽमहसं १०. १२२, १.
चित्रया २. १७, ८; ८. ६६, ८; १४.
चित्रऽयामं ३. २, १३.
चित्रऽरथं १०. १, ५.
चित्रराती इति चित्रऽराती ६. ६२, ५.
चित्रराती इति चित्रऽराती ६. ६२, ११.
चित्रऽराधसः १०. ६५, ३.
चित्रऽराधसं ८. ११, ९.
चित्रऽवाजान् ८. ७, ३३.
चित्रऽशोचिः ६. १०, ३.
चित्रऽशोचिषं ५. १७, २; ८. १९, २.
चित्रश्रवःऽतम १. ४५, ६.
चित्रश्रवःऽतमः १. १, ५; ८. ९२, १७.
चित्रश्रवःऽतमं ३. ५९, ६; ८. २४, ३.
चित्रऽसेनाः ६. ७५, ९.
चित्रस्य १. २२, ७.
चित्रा १. ६६, १; ९२, १२; ११३, ४; १२५, ६; १३४, ४; ३. ५७, ६; ४. १४, ३; ५२, २; ५. १८, ४; ५२, ११; ६३, ५; १०. ७५, ७; १०६, ३; १२३, ७.
चित्राऽइव ८. १०१, १३.
चित्राः १. १६५, १३.
चित्राः १. ३८, ११; ११५, ३; ११९, ८; ४. ५१, २; ६. ६०, २; ७. ७५, ३; ६; ८. ७, ७; १०. ७८, १; ९१, ५.
चित्रान् ४. २२, १०; ६. १७, २.
चित्राभिः ४. ३२, ५; ५. ४०, ३; ६. १०, ३; २६, ५; ८. ३, २; ७०, ६; ९. ६२, २५.
चित्रां १. ६३, ८; ५. ६३, ६; १०. १११, ७.
चित्राय १. १७, ७; १३९, ६; ३. ७, ९.
चित्रासु ६. ७२, ४.
चित्रिणीषु ४. ३२, २.
चित्रे १. ३०, २१.
चित्रेण २. ४, ५; ८. १, २३; ३९, ५.
चित्रेभिः ५. ६३, ३; ९. १००, ८.
चित्रेषु ३. २, ११.
चित्रैः १. ६४, ४.
चित्र्यं ५. ६३, ७; ७. २०, ७.
चिनवत् ४. २, ११.
चिनुयाम ९. ९७, ५८.
चिनुषे १०. ९१, ५.
चिनुहि ६. ५३, ४.
चिनोति १०. ४३, ५.
चिनोतु १०. ८७, ५.
चिन्वती ३. ६१, ४.
चियन्तु १. ९०, ४.
चिरं ५. ५६, ७; ७९, ९.
चिश्चा ६. ७५, ५.
चीकृपाति १०. १५७, २.
चुकुधं ८. १, २०.
चुकुधाम २. ३३, ४; १०. १४२, ३.
चुच्यवत् २. ४१, १०.
चुच्यवीरत ८. ९, ८.

चुच्युवे ८. ४५, २५.
चुमुरिं २. १५, ९; ६. १८, ८; २६, ६; ७. १९, ४; १०. ११३, ९.
चृत १. २५, २१.
चृतंति १. ६७, ४.
चेकितत् ९. १११, ३.
चेकितान २. ३३, १५.
चेकितानः ३. ५, १; २९, ७; ४. १४, २; ६. ३६, ३.
चेकितानं १०. १८३, १.
चेकिताना १. ११३, १५; ४. १४, ३.
चेकिते ६. ६१, १३.
चेकिते १. ५३, ३; ५५, ३; ११९, ३; २. ३४, १०.
चेतत् १. १६१, १६; ८. ६८, १८.
चेततः ४. ५, ४.
चेततां १०. ३५, १.
चेतति ७. ४६, २; ८. १२, १; ३२, २८.
चेतति १. १०, २; १२८, ४[२]; ३. ११, ३; ६. १२, ३; ७. ९६, ३; ८. १३, २०; ९. ६२, १०; १०६, २; १०. १७६, ३.
चेतते ३. १४, २.
चेतथ ५. ५९, ३.
चेतथः १. २, ५; ४. ४५, ६.
चेतनः २. ५, १; ३. १२, २; ९. ६४, १०.
चेतनं १. १३, ११; १७०, ४; ३. ३, ८; ४. ७, २; ८. १३, १८; ६२, ९; ९. ३१, १.
चेतंती १. ३, ११; ७. ९५, २.
चेतंते ९. ४७, २.
चेतयत् ४. १, ९.
चेतयति १. ३, १२.
चेतयते ९. ८६, ४२.
चेतयध्वं ३. ५३, ११.
चेतयंती १०. ११०, ८.
चेतयेथां ८. ९, १०.
चेतसा ५. ७३, ६; ९. १६, ४; २०, ३; ८३, २; ८६, ४२; १०. ४६, ८.
चेतारः ७. ६०, ५.
चेति १. ९३, ४; ४. १६, १४.
चेति १. ९२, १२; ११९, ४; ३. १२, ९; ४. ३७, ४; ४३, ६; ५५, ४.
चेतिष्ठ ८. ४६, २०.
चेतिष्ठः १. ६५, ५; ५. २७, १.
चेतिष्ठं १. १२८, ८; ७. १६, १; १०. २१, ७.
चेतुना ९. ८१, ३.
चेत्ता १. २२, ५.
चेत्तारं १०. १२८, ९.
चेत्यः ६. १, ५.
चेत्या १०. ८९, १४.
चेदयः ८. ५, ३९.
चेरवे ८. ६१, ७.
चैद्यः ८. ५, ३७.
चैद्यस्य ८. ५, ३८.
चो इति ५. २९, १३; ६. ६६, ३.
चोद १. ४८, २; ७. ९६, २.
चोदः ५. ६१, ३.
चोदः १. १४३, ६.
चोदत् ७. २७, ३.
चोदत १. १६८, ४; ५. ५६, ७.
चोदते ९. ६९, २.
चोदऽप्रवृद्धः १. १७४, ६.
चोदं २. १३, ९.
चोदय ६. ४७, १०; ७. ७७, ४.
चोदय १. ९, ५; ६; १०२, १०; ६. ४८, ९; ५३, ३; ७५, १३; ७. ३२, १५; ८. २३, २८; २४, २५; ९. ८, ३; ५०, १; ६५, १२; ७५, ५; ८५, २; ११०, ७; १०. १४१, ५; ६.
चोदयः १. १७५, ३.
चोदयः ६. २६, ३; ९. १७, ५; १०. २२, १०.
चोदयत् १०. ८०, २; १२३, १.
चोदयत १०. १०१, १२.
चोदयत १. १८८, ८.
चोदयतं १०. ३९, २.
चोदयत्ऽमति ५. ८, ६.
चोदयत्ऽमते ८. ४६, १९[२].
चोदयन् १. ८०, ५; ८. ९९, ४; १०. १०२, १२.
चोदयंता १. ११७, ३.
चोदयंती ७. ७९, ५.
चोदयाते ८. २४, १३.
चोदयामि १०. १२०, ५.
चोदयासि १. ९४, १५.
चोदयासे ६. ४६, १३; १०. २९, ८.
चोदयित्री १. ३, ११; ७. ८१, ६.
चोदस्व १. १०४, ७; ८. ७५, ६.
चोदामि ३. ४२, ८; ८. ६८, ७.
चोदितः ९. ७२, ५.
चोदिता १. ५१, ८; २. १२, ६; ८. ८८, ६; १०. २४, ३; ४९, १; १३३, १.
चोदितारा ५. ४३, ९.
चोदिष्ठेन ८. १०२, ३.
चोदीः १. ६३, ४.
चोदेथां ७. ७४, २.
चोदौ २. ३०, ६.
चोष्कूयते ६. ४७, १६.
चोष्कूयमाणः १. ३३, ३.
चोष्कूयसे ८. ६, ४१.
च्यवतानः ५. ३३, ९.
च्यवनः २. २१, ३; ६. १८, २; ८. ३३, ६; १०. ६९, ५.
च्यवनं ८. ९६, ४.
च्यवना २. १२, ४.
च्यवंत १. ४८, २.
च्यवंते १. १६७, ८; १०. १२४, ४.
च्यवं १. १६५, १०.
च्यवय १०. ४२, २; १०१, १२.
च्यवयति ४. १७, ५; ७. १९, १.
च्यवयतु १०. १७, ३.
च्यवयथ १. १६८, ६.
च्यवयन् ३. ३०, ४.
च्यवयंति १. ३७, ११; ६४, ३.
च्यवयंते ६. ३१, २.
च्यवयसि ३. ४३, ७.
च्यवयसि ८. ९२, ७.
च्यवयामः ४. १७, १६.
च्यवयामसि ४. ३२, १८.
च्यवानः १०. ५९, १; ६१, २; ११५, ४.
च्यवानं १. ११७, १३; ११८, ६; ५. ७५, ५; ७. ७१, ५; १०. ३९, ४.
च्यवाना ६. ६२, ७.

च्यवानात् १. ११६, १०; ५. ७४, ५.
च्यवानाय ७. ६८, ६.
च्योष्ठाः १०. १७३, २.
च्यौत्नः १०. ५०, ४.
च्यौत्ना ६. ४७, २; ८. २, २३.
च्यौत्नानि १. १७३, ४; ४. ३१, ९; ७. १९, ५; ८. ७७, ९.
च्यौत्नायं ६. १८, ८.
च्यौत्नेन १०. ४९, ११.
च्यौत्नैः ८. १६, ६.

छ

छदयत् ६. ४९, ५; १०. ३१, ४.
छदयति ३. ९, ७.
छदयथ ८. १, ६.
छदयंति ५. ७९, ५.
छदयाथ १. १६५, १२.
छदिः १०. ८५, १०.
छंत्सत् १. १३२, ६; १०. ३२, ३.
छंत्सि १. १६३, ४.
छंदः १. ९२, ६; ८. ७, ३६; ५२, १; १०. ८५, ८; १३०, ३.
छंदः ६. ११, ३.
छंदःऽस्तुभः ५. ५२, १२.
छंदयसे ८. ५०, ५.
छंदयाते १०. २७, ८.
छंदसां १०. ११४, ९.
छंदस्यां ९. ११३, ६.
छंदांसि १०. १४, १६; ९०, ९; ११४, ५; ६.
छंदुः १. ५५, ४.
छंद्यं ८. १०१, ५.
छर्दिः १. ४८, १५; ११४, ५; ४. ५३, १; ६. १५, ३; ४६, ९; १२; ६७, २; ७. ७४, ५; ८. ५, १२; ९, १; १५; १८, २१; २७, ४; २०; ६७, ६; ७१, १४; ८५, ५; १०. ३५, १२.
छर्दिःऽपौ ८. ९, ११.
छर्दिर्षः ६. ६७, ११.
छागः १. १६२, ३.
छादयामि ६. ७५, १८.
छायया ५. ४४, ६.
छाया १०. १२१, २.
छायाऽइव १. ७३, ८.
छायां २. ३३, ६.
छायांऽइव ६. १६, ३८.
छिद्रा १. १६२, २०.
छिंधि १. १३३, २.
छुबुकात् १०. १६३, १.
छेदि २. २८, ५.
छेद्म १. १०९, ३.

ज

जंहः ६. १२, २.
जक्षतः १. ३३, ७.
जक्षीयात् १०. २८, १.
जगत् १. ४८, ८; ८०, १४; ११३, ४; १५७, १; १६४, २३; १८६, १; २. २७, ४; ४. ५३, ३; ६. ४७, २९; ४९, ६; ८. ४०, ४; १०. २५, ६; ३७, ४; ५८, १०; ८८, ४; १७३, ४.
जगतः १. ३५, १; ८९, ५; १०१, ५; ११५, १; १५९, ३; ४. १३, ३; ५३, ६; ६. २२, ९; ३०, ५; ४९, ६; ५०, ७; ७. २७, ३; ३२, २२; ६०, २; ६६, १५; १०१, २; ६; १०. ६३, ८; १०२, १२; १२१, ३.
जगता १. १६४, २५.
जगतां २. ३१, ५; १०. ७५, २.
जगति १. १६४, २३.
जगती १०. १३०, ५.
जगतीषु १. १५७, ५; ६. ७२, ४.
जगत्ऽपौ ८. ९, ११.
जगंथ १०. १०८, ७; १८०, २.
जगन्म ४. १६, १८.
जगन्वांसः ८. ४५, १९.
जगन्वांसा ५. ६४, १.
जगन्वान् १. ११७, १५; ३. ३८, ६; ७. ८८, २; १०. १०, १.
जगम ७. ८८, ५; ८९, ३.
जगम्यात् १. ५८, ९; ६०, ५; ६१, १६; ६२, १३; ६३, ९; ६४, १५; १०४, २; ५. ३३, ५; ६. ५०, ८.
जगम्यां १. ११६, २५.
जगम्युः १. १७९, १; २.
जगाम १०. ५८, १; १७९, २.
जगाम १. १४५, १; १७९, ६; ५. ३१, १२; ७. १८, ९; ८. ४, ११; १००, १०; १०. २८, १; ११४, १.
जगायात् १०. २८, १.
जगार ४. १८, ८.
जगार १०. २७, १३; २८, ९; ३१, १०; ५५, ५.
जगुरिः १०. १०८, १.
जगृधुः २. २३, १६.
जगृभथुः ६. ७२, ४.
जगृभुः ५. २, ५.
जगृभ्म १. १३९, १०; १०. ४७, १.
जगृभ्यात् ५. ४२, २; १०. ३१, २.
जगृभ्रिरे ४. ७, २.
जगृभ्रे १. १४८, ३; ७. ४, ३.
जगृभ्रे ५. ३२, ११; ७. १८, ८; १०. ६१, ८.
जगृभ्वान् ४. २३, ४.
जगृहे १०. १२, ५.
जग्धं १. १४०, २.
जग्ध्वाय १०. १४६, ५.
जग्मतुः १०. ४०, १४.
जग्मथुः ८. ७३, ४; १०. २२, ६.
जग्मयः १. ८५, ८; ८९, ७.
जग्मये ६. ४२, १; ८. ४६, १७.
जग्मिः २. २३, ११; ७. २०, १; ८. ९३, २२.
जग्मिरे ६. १९, ५; १०. ५, २.
जग्मी इति १०. १०६, ८.
जग्मुः ३. १, १३; ६. ३४, १; १०. ६, ६; १३१, २.
जग्मुः १. ३२, २; ३. ३६, ६; ६०, १; ४. ३३, ६; ४१, ८; ५. ४१, ४; ५६, २; ६. २४, ६; ८. २४, ११; १०. १११, ८; १०.
जग्मुषः ७. ३९, ३.
जग्मुषी १. ११९, ५.
जग्मुषीः १. १२२, १४.
जग्मे १. १६४, ८.
जग्रभ ८. ६, १०.
जग्रभ १०. १८, १४.
जग्रसानाः १०. ९४, ६.
जग्रसानान् ४. १७, १; १०. १११, ९.

जग्रसीत ५. ४१, १७.
जग्राहं १०. १६१, १.
जघनंत् ९. २३, ७.
जघनां १. २८, २.
जघनांन् ६. ७५, १३.
जघनें ५. ६१, ३.
जघंथ १. ५२, १५; ८०, २; २. १५, ९; ३०, ४; ७. २१, ६.
जघंथ १. ८०, ४; ३. ३०, ८; ६. ३१, ४; ७. १८, २०; ८. ६, १४; ९६, १७; १०. ७३, ६; ७; १११, ६.
जघन्वान् १. ३२, ११; ५२, ८; ५९, ६; ८०, १०; १७४, ६; २. १४, ७; ३. ३२, ६; ३६, ८; ४. १७, १; १८, ७; १९, ८; ४२, ७; ५. ३२, २; ७. २३, ३; १०. ८, ८; २७, ३; ११३, २.
जघानं १. ८४, १३; २. १२, १०; ११; १४, २–५; ४. १८, ९; ५. २९, ८; ८५, १; ६. १७, ९; ९. २३, ७; १०९, १४; १०. २३, ५; ८९, ७.
जघान १. ३२, ७; ५१, ९; २. १५, १; ३. ३३, ७; ५. ३२, ३; ४; ६; ६. ४४, १४; ७. १८, १७; २०, ३; २१, ४; ३३, ३; १०. ८९, २.
जघासं १. १६२, १४.
जघास १. १९१, ११.
जघ्रथुः ७. ९९, ४.
जघ्निः ९. ६१, २०.
जघ्नुषः १. ३२, १४.
जघ्निः १. १६२, १५.
जंगृह्रे १. १२६, ६.
जंघनः ९. ९, ७.
जंघनत् ४. २४, १०; ९. ६६, २४.
जंघनत् ३. ५३, ११; ६. १६, ३४.
जंघनंत २. ३१, २.
जंघनंत १. ८८, २.
जंघनानि १०. ११९, १०.
जंघनाव ८. १००, २; १०. ८३, ७.
जंघंति ६. ७५, १३.
जंघा १. ११६, १५; ११८, ८.
जघ्नतः ९. ६६, २५.

जजनुः ८. ९७, १०.
जजस्तं ४. ५०, ११.
जजानं १. १६०, ४; २. १२, ३; ७; ४०, ५; ३. १, १२; ३२, ८; १४; ४. १७, ४; १२; ५६, ३; ८. ९६, ६; १०. २, ६; ७; २८, ६; ३१, ४; ८२, ७; १२१, ९[2].
जजान २. ३५, २; ३. १, १३; २९, ३; ५५, १९; ४. ५८, ४; ५. २, २; ७. २०, ५; ८. २५, ३; १०. २०, ९.
जज्ञतुः ७. ९०, ३.
जज्ञतुः ९. ६८, ५; १०. ५, ३.
जज्ञानः १. १२, ३; ६३, १; ३. ४४, ४; ६. ४०, २; ७. ९८, ३; ८. ७७, १; ९६, २१; ९. ३, १०; ८६, १४; ९७, ३१; १०९, ८; १०. ६, ७; ४५, ४; ११३, ४; १२०, १.
जज्ञानं ३. १, ४; ६. २१, ७; ३८, ५; ९. २९, २; ८६, ३६; ९६, १७; १०२, ४; १०९, १२.
जज्ञाना १. २३, ४.
जज्ञानाः ५. ३३, ५; १०. १४, २.
जज्ञिरे ६. ५२, १५; १०. ६२, ६.
जज्ञिरे १. ६४, २; ४; १०. ६२, ५; ९०, ९[2]; १०.
जज्ञिषे ५. ३५, ३; ४; ७. ७, ३; १०. ९५, ११.
जज्ञिषे १. ५१, ६; २. १, १४; ८. १५, १०; १०. १३३, २.
जज्ञुः ७. ६२, ४; ७९, ४; १०. २८, ७.
जज्ञुः १. १५१, ३.
जज्ञे ६. ४५, १६; ७. २८, ३; ८. २४, १५; ९. ११४, २; १०. १२०, १.
जज्ञे १. १२१, ६; ३. ३१, ३; ५५, १; ६. ९, ४; ७. २०, १; ३३, १२; ९. १०८, १२; १०. ४५, १; ६१, ९; ७२, ४; १७०, २.
जझ्झतीःऽइव ५. ५२, ६.
जंजणाऽभवन् ८. ४३, ८.
जंजती १. १६८, ७.
जठरें ५. ३४, २; ६. ६७, ७; ६९, ७; ९. ७०, १०; ८१, १; १०. १०४, २.
जठरस्य १. ११२, १७.
जठरात् ३. २९, १४; १०. ९२, ८.
जठरें १. १०४, ९; २. १६, २; २२, २; ३. २२, १; ३५, ६; ४०, ५; ४२, ५; ४७, १; ९. ६६, १५; ७२, २; ८५, ५; ८६, २२; ९५, १; १०. ९२, ५; ९६, १३; १०६, ८.
जठरेषु १. ५४, १०; ९५, १०; ३. २, ११; ८. ९२, २३; ९. ७६, ३; ८६, २३.
जठलस्य १. १८२, ६.
जत्रुऽभ्यः ८. १, १२.
जनः १. ४१, १; ५४, ७; ८६, १; १२२, ८; ९; १३६, ५; १८२, ३; ५. ३४, ७; ४८, २; ६. २, ३; १८, ८; ३६, २; ७. २०, ६; ८; ५५, ५; ६; ८. ४, १२; ५, ३९; १८, १३; ४७, ६; ९३, ११; ९. ३५, ६; ८८, ५; १०७, १०; १०. २६, २; ३२, ४; ५७, ५; ६३, १७; १३३, ४; १४१, ४.
जनत् २. २१, ४; ४०, २; ४. ४०, २.
जनत ४. १, १[2]; १०. १२३, ७.
जनथः १. ११९, ७.
जनना २. ४०, १[2].
जनंत २. १८, २; ७. ७, ४; ९. २३, २.
जनंतः ९. १०, ५.
जनंती ३. ६१, ४.
जनऽपाने ९. ११०, ५.
जनऽभक्षः २. २१, ३.
जनं १. ३१, १७; ४०, ७; ४४, ६; ४५, १; ९; १०; ४९, २; १६६, ८; २. २३, ४; ३०, ११; ३. ५३, १२; ४. ९, १; ५. १३, ३; ६५, ६; ८०, २; ६. १६, ६; १९, १२; २१, ४; ३४, ४; ४९, १; ५२, १२; ७. ३६, २; ८. ५, ३३; ६, ४८; ४४, ९; ९. ६३, २४; ७१, ८; ८०, ५; ८४, १; ३; १०. ५३, ६; ६०, १; ६३, ९; १८०, ३.

जनमाने ८. ९९, ३.

जनेऽजनं ५. १५, ४; १०. ९१, २.

जनंऽसहः २. २१, ३.

जनयं ९. ९६, १२; ९७, ३६; १०. ५३, ६.

जनय १. ११३, १९; ७. ४१, ३; ८. १३, ७.

जनयः १. ६२, १०; ७१, १; ८५, १; १८६, ७; ४. ५, ५; १९, ५; ५. ६१, ३; १०. १८, ७; ४०, १०; ४३, १; ११०, ५; १२४, ७.

जनयः १०. ५५, २.

जनयत् ६. ५२, १६; १०. ४५, ८.

जनयत् १. ७१, ८; १०. ६७, १.

जनयत १. ९५, ४; ३. २९, ५; ९. ९५, १.

जनयतं १. १८५, ३.

जनयतु १०. ८५, ४३.

जनयथ १०. ९, ३.

जनयथ ५. ५८, ४.

जनयन् १. ३२, ४; १४०, ८; ३. २, १२; ३४, ४; ४. २१, ५; ६. ३०, ५; ७. ५, ६; ७; ९. ३, १०; २५, ५; ४२, १^{२}; ६६, ४; ७८, १; ८६, २०; ३३; ९७, ४०; १०६, १२; १०७, १८; २६; १०८, १२; ११३, ६; १०. ३, २; ८, ४; ५५, ८; ८१, २; ३.

जनयन् १०. ६६, ९.

जनयंत ३. ३१, २; ४९, १; ७. २२, ९; १०. ८७, १३.

जनयंत १. ९५, २; १४१, २; ३. २, ३; ५. ४९, ३; ६. ७, १; २; ७. १, १; ३१, ११; १०. ६६, २; ९१, ६.

जनयंतः १. ८५, २; ७. ७५, ३; ९. ७३, २; १०. ६५, ११.

जनयंता ७. ९९, ४.

जनयंतीः १०. १२१, ७; ८.

जनयस्व ६. १८, १५.

जनयामि १. १०९, २.

जनये ७. २६, १; १०. ९१, १४.

जनऽयोपनः १०. ८६, २२.

जनऽराज्ञः १. ५३, ९.

जनऽश्रियं ६. ५५, ६.

जनसी इति २. २, ४.

जनस्य १. ७०, १; ३. ४३, ५; ५. ११, १; ६. २२, ९; ३८, १; ८. १९, १५; २१, ११; ९. ३५, ५; ९१, २; १०. ९२, ३; १५९, ६.

जना १. १३१, ३; ९. ८६, ४२.

जनाः १. ७४, ५; ८९, १०; १०२, ५; ६; २. २४, १०; ३. २, ५; ५९, ८; ४. ३८, ९; ६. ११, ४; ५१, ११; ७. ६३, ४; ८. १, ३; ५, ३८; ४०, ७; ४३, २९; ४६, ३२; ७४, ६; १०. ४२, ४; ४५, ६; ५३, ५; ८९, ८.

जनाः ५. ३१, १२; १०. ५३, ४.

जनात् १०. ८५, ३१.

जनान् १. ३५, ५; ३७, १२; ५०, ३; ६; ५९, १; ६४, १३; १२०, ११; १३२, ५; १४०, १२; १७३, ८; २. २, १०; २०, २; ३. ४६, २; ५९, १; ५. ३३, २; ६. १०, ५; २०, १; ४६, ४; ४९, १५; ६७, १; ३; ६८, ५; ७. १८, ११; ५५, ७; ८. १९, १४; ३२, २२; ६०, १६; ९. ९२, ३; १०. १४, १२; ६०, ३.

जनानां १. २५, १४; ६६, २; ७५, ३; ४; ८१, ९; १७७, १; १९१, ४. ३. १८, १; २३, ३; ३०, १; ४. ४, ९; ९, ५; १६, १७; ५. १, १; २, ६; १६, २; ६६, ४; ६. १, ५; ७, १; ३६, ४; ४४, ९; ४५, ९; ७. १६, २; ७; ४९, ३; ५६, २४; ६१, ५; ६३, २; ७४, ६; ७५, ४; ७९, १; ८३, ३; ८. १, ४; ५, १३; १५, १०; १९, ३३; २४, ४; ४५, २८; ५४, ७; ६४, ३; ८१, ७; १०३, ६; ९. ५२, ४; ६४, २७; ८७, ३; ६; ११२, १; १०. १, ५; २, २; १४, १; २७, ९; १९; ३३, १; ४३, ६; ४७, ८; ६९, ५; ६; ८९, १६; ९६, १२; १०७, ५.

जनानां १. १८१, १; ६. १५, १९.

जनामसि ३. २, १.

जनामि ८. ४३, २.

जनाय १. ३६, १९; ४४, ४; ८४, १७; ९२, १७; ९३, ८; ११७, ६; १३०, ५; १५३, ३; १६६, १२; २. ३४, ८; ३५, १५; ३. ५९, ९; ४. २, ४; ४४, ४; ५१, १; ५. ५८, ४; ६. १८, १४; २२, ८; ७३, २; ७. १६, १२; ३४, ६; ६५, ४; ७०, ३; ५; ७५, ६; ८२, १; १०४, १२; ८. २३, २८; १०१, १५; ९. ९, २; ११, ३; ३९, २; ६४, १४; १०. ४०, ४; १०२, ८; १२५, ६.

जनापाट् १. ५४, ११.

जनासः १. ३६, २; १६६, १४; २. १२, ९; ३. १९, ४; ५८, ४; ५. २, १; ३, ११; २३, ३; ३५, ६; ७. ६, ६; ५६, २२; १००, ४; ८. ५, १७; ६, ३७; २६, २२; ४३, २७; ७४, २; १२; १०. ४, २; ८१, ६; १०४, ५; ११२, ७.

जनासः २. १२, १–१४; ३. ५३, २३; ५५, १८; ४. २४, १; ५. ४७, ५.

जनि १. १४१, १; ८. ७, ३६.

जनितः ६. ७६, ४.

जनित्ता ३. १, १२; १०. २, ६; २०, ९; २८, ६.

जनिता १. ९६, ४; १२९, ११; १६४, ३३; २. २३, २; ३. ४९, ४; ४. १, १०; १७, ४; ६. ५९, २; ८. ३६, ४^{२}; ५^{२}; ९९, ५; ९. ८६, १०; ८७, २; ९०, १; ९६, ५^{७}; १०. १०, ५; ८२, ३; १२१, ९.

जनितारा ६. ६९, २.

जनितुः ३. १, १०; ५४, ९; ४. १७, १२.

जनितोः ४. ६, ७.

जनित्रं १. १६३, ४; ७. ३४, २; ५६, २.

जनित्री १. १२४, ५; २. १३, १; ३०, २; ३. ४८, २; १०. १३४, १^{२}.

जनि॒त्री इति॑ १. १८५, ६; ३. ३१, १२; ७. ९७, ८; १०. ११०, ९.
जनि॑त्रीः ३. ५४, १४; ६. ५०, ७; १०. १, ४; ३०, १०.
जनि॑त्रीं १०. ३५, ७.
ज॒नित्रे॑ १०. ५६, १.
ज॒नि॒ऽत्व॒नार्य॑ ८. २, ४२.
जनि॑ऽत्वं १. ६६, ४; ८९, १०.
ज॒नि॒ऽत्वं १०. १८, ८.
जनि॑ऽत्वाः ४. १८, ४.
ज॒नि॒त्वी १०. ६५, ७.
जनि॑ऽत्वैः १०. ४५, १०.
ज॒नि॒ऽदां ४. १७, १६.
ज॒नि॒धाःऽईव १०. २९, ५.
जनि॑ऽभिः २. ३६, ३; ३. २६, ३; ६. ५०, १३; ७. १८, २; १०. ६४, १०.
जनि॑ऽभ्यः १०. १८३, ३.
जनि॑म २. ३५, ६; ३. १, २०; ३१, ८; ३८, २; ५४, ८; ४. २, १७; १८; ५. ३, ३; ६. १५, १३; १८, ७; ७. ६२, १; ८. ४६, १२; ९. ६८, ५; ९७, ७; १०. ६३, १; १४२, २.
जनि॑मन् ३. १, ४; ४. १७, २; २२, ४; ६. ६३, ५.
जनि॑मानि ३. ४, १०; ३८, ८; ४. १, ७; २७, १; ७. ४२, २; ६०, ३; ९. ८३, ४; १०८, ३; १०. ८९, ३.
ज॒नि॒ऽयंतः ४. १७, १६; ७. ९६, ४.
जनि॑ऽवतः ५. ३१, २.
जनि॑ऽवान् ५. ४४, ७.
ज॒नि॒षी॒ष्ट ४. १८, १; ७. ८, ६.
जनि॑ष्ट ५. १, ५; ९, ३; ७. ३, ९; १०. ३१, १०; ४०, ९.
ज॒नि॒ष्ट ८. ५१, ४; ८; ९. ९८, ९.
जनि॑ष्टां १०. ४६, ९.
जनि॑ष्टो इति॑ १०. ९५, १०.
जनि॑ष्ठाः १. ६८, २; १०. ७३, १.
ज॒नि॒ष्ठाः ७. २८, २.
ज॒नि॒ष्य॒ते १. ८१, ५; ७. ३२, २३.
जनि॑ष्व ६. १५, १८.
जनीं॑ ४. ५२, १.
जनीः॑ १. १६७, ७.
जनीः॑ऽइव ७. २६, ३; ८. १७, ७.
जनी॑नां १. ६६, ४; ५. ४६, ८; ९. ८६, ३२.
ज॒नुषः॑ १. ६१, १४; २. १७, ६; ६. ६६, ४; ८. ६६, ९.
ज॒नुषं॑ १. १३९, ९; १४१, ४; २. ४२, १.
ज॒नुषा॑ १. ९४, ६; १०२, ८; १५६, ३; ३. १, ३; ९; २, २; ४६, ४; ४८, ४; ४. २०, ७; ५. २९, १४; ३०, ७; ५७, ५; ५९, ६; ६. ४, ४; १५, १; ७. २०, ३; २१, १; ८. २१, १३; १०. ८५, २१; ९२, १५.
ज॒नुषां॑ १. १५१, १; ४. १७, २०.
ज॒नुषी॒ इति॑ ९. ७०, ३.
ज॒नुषे॑ ५. ४५, ३.
ज॒नूंषि॑ ७. ४, १; ५६, २; ८६, १.
ज॒नूः॑ ७. ५८, २.
जने॑ १. ३४, ४; ४८, ११; ६९, २; ११३, १९; २. ४, १; ४. ५४, ३; ५. १४, २; २१, २; ३३, १; ७४, २; ६. १६, १; ४६, ८; ७. ६२, ५; ८९, ५; ८. २३, ८; ६४, १०; ७२, ३; ९. ६१, २८; १०. २२, १; २७, १२; ३९, ५; ६८, २; ११८, ९; १४५, ४.
जने॑ऽजने ५. ६५, २; ६७, ४.
जने॑न २. २६, ३; ७. ५३, २; ९३, ५.
जने॑भ्यः १. ७, १०; ५५, ५; ५८, ६; १०. १५६, ४.
जने॑षु १. ५५, ४; ९५, २; २. २३, १५; ३९, २; ३. ३७, ९; ५८, ५; ४. ५१, ११; ५. ३१, १३; ३२, ११; ६. ४४, ११; ७. २३, २; ३०, २; ८. ५३, ३; ९. ६५, २३; १०. २२, २; ५४, २; ६४, ११; १०६, २.
जनौ॑ ५. ३४, ८.
ज॒न्तवः॑ १. ४५, ६; ७४, ३; ८१, ९; ९४, ५; ५. ७, २; १९, ३; १०. ४८, १; ४९, २.
ज॒न्तवे॑ ३. २, १२.
ज॒न्तुः ९. ६७, १३.
ज॒न्तुऽभिः॑ ३. ३, ६; १०. १४०, ४.
ज॒न्तुं ७. ५८, ३.
ज॒न्तोः ५. ३२, ७; ७. ९, १; २१, ५; १०४, १६.
जंत्वं॑ ८. ८९, ६.
जन्म॑ १. ७०, १; ३; ७१, ३; १५१, ३; २. ६, ७; ५. ४१, १४; ६. ११, ३; ५१, २; १२; ७. ३३, १०; १०. ६४, १६.
जन्मं॑ऽइव ३. १५, २.
जन्म॑न् २. ९, ३; ८. ६९, ३; १०. ५, ७.
जन्म॑नः ४. ३४, २; ७. ४६, २; ९. ८१, २; १०. १७६, ४.
जन्म॑ना १. ८७, ५; २. २६, ३; ३. २६, ७; ९. ३, ९; १०. ६४, १४.
जन्म॑नि १०. ६४, ५.
जन्म॑नी॒ इति॑ १. १४१, ११; ८. ५२, ७.
जन्म॑ने १. २०, १; ३१, ७; ५८, ६; १६६, १; ९. ८५, ६; १०८, ८; १०. ३७, ११.
जन्म॑न्ऽजन्मन् ३. १, २०.
जन्म॑ऽसु १०. ६४, ५.
जन्मा॑नि १. ५०, ७; २. ३८, ८; ७. १०, २.
जन्यः॑ ४. ३८, ६; १०. ९१, २.
जन्यं॑ २. ३७, ६.
जन्या॑ २. ३९, १; १०. ४२, ६.
जन्या॑ऽइव २. ६, ७.
जन्या॑त् ४. ५५, ५.
जन्या॑सः ९. ४९, २.
जन्युः॑ १०. १०, ३.
जबा॑रु ४. ५, ७.
ज॒भरं॑त् ४. २, ६; १२, २.
ज॒भ॒र्थ॒ ४. १९, ९.
ज॒भार॑ ३. ४३, ७; ४. १८, ४; ८. ५६, ४.
ज॒भा॒र॒ १. ३२, ९; ९३, ६; ११५, ४; २. ३०, ३; ४. १८, १३; २७, २; ४; १०. ५, ५; ६८, ८; ९; १८१, १.

जुभ्रिरे १०. ६४, ६.
जुभ्रिरे १. ७२, ४; १९१, १४.
जुभ्रिषे ९. ८६, २९; १००, ९.
जुभ्रुः ३. ५४, १; ४. ७, ४; ७. १८, १९.
जुभ्रे १. ६१, ८.
जुमत्ऽअग्निना ३. ६२, १८; ८. १०१, ८; ९. ६२, २४; ६५, २५.
जुमद॑ग्निऽदत्ता ३. ५३, १५.
जुमदग्निऽवत् ७. ९६, ३; ९. ९७, ५१.
जंभय॑ १. २९, ७; २. २३, ९.
जंभय॑तं १. १८२, ४.
जंभय॑न् १. १९१, ८.
जंभय॑तः ७. ३८, ७.
जंभ॑ऽसुतं ८. ९१, २.
जंभा॑सः ८. ६०, १४.
जंभिष॑त् १०. ८६, ४.
जंभे॑ १. ३७, ५.
जंभे॑भिः ७. ७, २.
जंभैः॑ १. १४३, ५; १४८, ४; ४. ७, १०; ७. ३, ४; १०. ८७, ३; ११३, ८.
जय॑ ६. ३५, २; ८. ८९, ४.
जय ६. ७५, १; ८. १५, ६; १२; ७५, १२.
जय॑त् १०. ४३, ५.
जय॑त १०. १०३, १३.
जयत १०. १०३, २.
जय॑तः १०. ३४, ७; ३८, २.
जय॑तं ८. ३५, ११.
जयतं १. १०८, १३.
जय॑तां १०. १०३, ९; १०.
जय॑तांऽइव १. २३, ११; २८, ५.
जय॑ति ६. २१, ४.
जयति १. ३६, ४; ४. ५०, ९; ६. ७५, ५; ७. ३२, ९; ९. ८६, ४०.
जयतु ६. ४७, २६.
जय॑न् ४. १७, १०; ५. ३१, ६; ६. ७३, २; ९. ८५, ४³; १०. १०३, ४.
जय॑तं १. ९१, २१; ५. ४४, १; ६. ७५, १८; १०. ४६, ५; १०३, ६; १२०, ४; १६७, २.
जयंतां १०. ८७, १८.

जय॑ति १०. १५९, ५.
जयंति ८. १६, ५.
जयं॑ती १. ११६, १७; १२३, २.
जयं॑तीनां १०. १०३, ८.
जयंतु ६. ४७, ३१; १०. १०३, ११.
जयसि ९. ८३, ५.
जया॑ः १. ८०, ३.
जयाति ५. ३७, ५; १०. ४२, ९; ५२, ५.
जयाथ १०. १०१, ७.
जयामसि ४. ५७, १.
जयामि १०. ४८, १.
जया॑व १. १७९, ३.
जयासि ६. ३५, २; ८. ९६, ७.
जयुषा॑ १. ११७, १६; ६. ६२, ७; १०. ३९, १३.
जयेथे इति॑ ६. ६९, ८.
जये॑म १. ८, ३; १२३, ५; ८. २१, १२; ६८, ९; ९२, ११; ९. ६१, २३; ८५, ८.
जयेम १. १०२, ४; २. ४०, ५; ४. २०, ३; ५. २, ११; ४, १; ६. ८, ६; ७५, २³; ७. ८२, १; ९८, ४; १०. १८, ९; ४२, १०; १०२, ११; १२८, १.
जरणा॑ १. १२१, ६.
जरणा ४. ३३, ३.
जरणाऽइव १०. ४०, ३.
जरणा॑ः १. १४१, ७.
जरणा॑ ७. ३०, ४; १०. ३७, ६; ३९, ८.
जरणिऽप्राः १०. १००, १२.
जरण्यया॑ १. ११९, ७.
जरण्युः १०. ६१, २३.
जर॑तः १०. ३४, ३; ८०, ३.
जर॑तं ७. ६७, १०.
जरत्ऽअष्टिः १०. ८५, ३६.
जरत्ऽअष्टिं ७. ३७, ७.
जरतां ४. ४, ८.
जर॑तीभिः ९. ११२, २.
जर॑ते ६. ६५, ४.
जरते १. ५९, ७; १२७, १०; १८१, ९; ७. ६८, ९; ७८, २; १०. ४५, १; ६९, १.

जर॑तोःऽइव ८. ७३, ११.
जरत्ऽविषं॑ ५. ८, २.
जरध्यै॑ ७. ६७, १.
जरंत १०. ३१, ७.
जर॑ंत १. ११७, १३.
जर॑ंता १. १६१, ७.
जर॑ंति ६. २४, ७.
जरंते १. २, २; ४. ४५, ५; ५१, ८; ५. ८०, १; ७. ७२, ४; ८. २, १२, १६; ८१, ९.
जर॑माणः ६. ६२, १; ७. ७३, ३; १०. ९१, १; ११८, ५.
जर॑माणं ३. ५१, १.
जर॑माणस्य ६. ६२, ४.
जर॑माणाः २. २८, २.
जरयन् २. ८, २.
जरय॑तं २. १६, १.
जरयं॑ती १. ४८, ५; ९२, १०; १२४, १०; ७. ७५, ५.
जरयं॑तीः १. १७९, १.
जरसः॑ ७. ७१, ५; ८. ६७, २०.
जरसे॑ १. ८९, ९; १०. १८, ६.
जरसा॑ १०. ८६, ११.
जर॑से १. ९४, १४.
जरसे ५. १५, ४.
जर॑स्व ३. ३, ७.
जरस्व १. १२३, ५; ७. ९, ६; ७६, ६.
जरा १०. ३२, ५.
जराते ५. ३७, २.
जरा॑ऽबोध १. २७, १०.
जरां १. १४०, ८; ५. ४१, १७.
जरामहे २. २३, ६; ३. ४१, ७.
जरा॑य १. १६४, ११; २. ३४, १०.
जरायु १०. १०६, ६.
जरायु॑णा ५. ७८, ८.
जरायै॑ १. ३८, १३.
जरि॑तः ८. ६०, १९.
जरितः ३. ३३, ८; ५. ४२, १४; ६. ५०, ६; ८. ९६, १२; १०. २८, ४; ४२, २.
जरितरिति॑ ३. १५, ५; ८. १००, ६; १०. २७, १; ४२, १.

जरिता १. ३८, ५; ४६, १२; ६३, २; १६५, १४; ३. ५१, ३; ५२, ५; ४. १७, १९; ५. ३६, ३; ४; ४३, १; ८. ४४, २८; १०. ६, १; ५९, २; १००, ६; ११; १४२, १.
जरितारः १. २, २; १८०, ७; ३. १२, ५; ६. १९, ४; २१, १०; २२, ४; ७. १८, १; २३, ४; ३२, २; १०. ८२, ४.
जरितारं १. १८९, ४; २. ९, ५; ४. ४३, ७; ५. ३, ११; ७५, ८; ६. २३, ३; ३२, ४; ७. २०, २; ९; ८९, ४; १०. ८०, ७.
जरितुः १. ५३, ३; १८२, ४; ३. ७, ६; १२, २; ६०, ७; ५. ४३, १०; ८७, ८; ६. ५, ६; ७. ९४, २; ८. १३, ७; २४, ६; ३५, १३; ८५, ४; ९. ४०, ५; १०. ३१, ५; ४०, ६; १०४, ७.
जरितृऽभ्यः १. ३०, १०; १७५, ६; १७६, ६; १७८, १; ३. ५१, ६; ८. २, २४; ३२, ११; ४५, १२; ४९, १; ७१, ९; ९. २०, २; ९४, ४.
जरितृणां १. ३०, १५; ४. ३१, ३; ७. ६६, ३.
जरितॄन् ७. ३, ८; ८. ६१, १७.
जरित्रे १. १८५, ३; २. ११, २१; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; ३३, ११; ३४, ६; ३८, ११; ३. १, १५; ३४, ५; ४. १६, १६; १८; २१; १७, २०; २०, ९; २३, ३; ६. २३, १०; ३५, ३; ४; ४७, २०; ७. २०, १०; २३, ५; ८. ६६, २; ९७, ८; १०. ४२, ७; १३३, ७.
जरिमा १. ७१, १०; १७९, १; ४. १६, १३; ५. ४१, १५; १०. ३२, ८; ५९, ४.
जरिमाणः १०. २७, २१.
जरिमाणं १. ११६, २५.
जरिम्णे १०. ८७, २१.
जरूथं ७. १, ७; ९, ६; १०. ८०, ३.
जरेत ४. ३, १५.
जरेथां ३. ५८, २.
जरेथे इति २. ३९, १; १०. ४०, ३.
जर्भरी इति १०. १०६, ६.
जर्भुरत् २. २, ५; १०. ९२, १.
जर्भुराणः २. १०, ५.
जर्भुराणा १. १६३, ११; २. ३९, ३.
जर्भुरीति ५. ८३, ५.
जर्हृषंतं ६. १७, ४.
जर्हृषाणः १. ५२, २; ७. २१, ४; १०. १६, ७; १०२, ४.
जलाषः २. ३३, ७; ७. ३५, ६.
जलाषऽभेषजः ८. २९, ५.
जलाषऽभेषजं १. ४३, ४.
जल्गुलः १. २८, १–४.
जल्पिः ८. ४८, १४.
जल्प्या १०. ८२, ७.
जळ्हवः ८. ६१, ११.
जवनी १. ५१, २.
जवसा १. ११८, ११; ४. १७, ३; २२, ६; ५. ७८, ४; ८. ८९, ४.
जवसा ४. २७, १.
जवसे ३. ५०, २.
जवांसि ४. २१, ८.
जविनीभिः २. १५, ६.
जविष्ठं ६. ९, ५.
जविष्ठा ४. २, ३.
जवीयसा ८. ७३, २; १०. ३९, १२.
जवीयान् १. ११७, २; ११८, १; १८१, ३; १८३, १; ९. ९७, २८; १०. ११२, २.
जवे १. ११२, २१.
जवेते इति ३. ३३, १.
जवेन १०. १११, ९.
जवेषु १०. ७१, ८.
जसमानं १. ११२, ६.
जसमानाय ७. ६८, ८.
जसुः १०. ३३, २.
जसुं १०. ६८, ६.
जसुरये १. ११६, २२; ६. १३, ५.
जसुरिं ४. ३८, ५; ५. ६१, ७.
जस्यत १. १९१, ७.
जस्वने ६. ४४, ११.
जहत् ९. १४, ४.
जहति ४. १८, ११.
जहतीः ७. ५, ३.
जहतीषु १०. ९५, ८.
जहतुः १०. ६१, ६.
जहा ८. ४५, ३७.
जहाति ९. ६४, २०; ७१, २; १०. १८, ५.
जहाति १. ९५, ७.
जहातु ३. ५३, २१.
जहाम १०. ५३, ८.
जहामि १०. १२४, २.
जहामि १०. १२४, ४.
जहि १. १३१, ७; ३. ३०, ६; १६^{2}; ४७, २; ४. ३, १४; २२, ९; ५. ३, ७; ६. १६, २९; १७, ३; २५, ३; ४४, ११; १७^{2}; ५१, १४; ७. २५, ३; १०४, २२; २४; ८. ४५, ४०; ५३, ४; ९. ८, ७; ६१, २६; ६३, २८; ७८, ५; ७९, ३; ८५, २; ८६, ४८.
जहि १. २९, ७; ३६, १६; ४२, २; ९४, ९; १३३, ३; १७६, ३; ४; २. ३०, ४; ६. ५३, ४; ७. १८, १८; १०४, १९; ८. १७, ९; ६१, १३; ६४, १; ९. ४, ३; १३, ८; ६१, २८; ६७, २१; ८५, २; १०. ८३, ३; ८७, ७; १५२, ३; ४.
जहितः ८. ५, २२.
जहितस्य १. ११६, १०.
जहिता ४. ३०, १९.
जहुः २. २४, ७; ७. १८, १५.
जहुः ७. ६८, ७; १०. ७१, ८.
जहृषाणेन १. १०१, २.
जह्नावीं १. ११६, १९.
जह्नाव्यां ३. ५८, ६.
जाः १. १४३, ८; ६. ४७, २१; ९. ७१, ९; ९३, १.
जाःऽपतिः ७. ३८, ६.
जाःऽपतिं १. १८५, ८.
जाःऽपत्यं ५. २८, ३; १०. ८५, २३.
जागर १०. १४९, ५.
जागरूके इति ३. ५४, ७.

जागार ५. ४४, १४[३].
जागार ५. ४४, १५[३]; १०. १४४, ५.
जागृतं १. २१, ६; ७. १०४, २५.
जागृवत्ऽभिः ३. २९, २; ७. ५, १; १०. ९१, १.
जागृऽवांसः १. २२, २१; ३. १०, ९; ६. १, ३.
जागृऽवांसं ८. ५, ३६.
जागृऽवांसा १. १३६, ३.
जागृवि ८. ८९, १.
जागृविः १. ३१, ९; ३. २, १२; २६, ३; २९, १; २; ५. ११, १; ८. ४४, २९; ९. ३६, २; ४४, ३; ७१, १; ९७, २; ३७; १०६, ४; १०७, ६; १२; १०. ३४, १.
जागृविं ३. २८, ५; ३७, ८; ६. १५, ८.
जागृवे ३. ३, ७; २४, ३; ८. ९२, २३.
जागृहि १०. ८७, २४.
जागृहि ९. ६१, २४; ८२, ४; १०. २५, ८; ८५, २८.
जाग्रतः १०. १६४, २.
जाग्रत्ऽस्वप्नः १०. १६४, ५.
जातः १. ६६, ४; ६९, ३; ८१, ५; ९८, १; १३०, ९; १४५, ४; १५२, ५; १६५, ९; २. १२, १; १३, १; २२, ३; ३. ३, १०; ५, ८; ८, ५; २९, ७; १०; ३२, ९; १०; ४८, १; ४. २, २; ७, ९; २०, ६; ५. १४, ४; ३०, ४; ६. २९, ६; ७. १३, ३; ३२, २३; ३३, ११; ९९, २; १०१, १; ८. ४५, ४; ७७, ८; ९. ९, ३; ६२, १५; ७४, १; ९४, ४; १०. १, १–३; ६; २१, ५; ४६, १; ३; ९०, ५; १३; ९५, १२; ११०, ११; १२१, १; १४८, २; १४९, ३; १५३, २; १६८, ३.
जातःऽजातः ७. ९०, २.
जातं १. ८३, ५; ८९, १०; ११७, १६; १५६, २; १६३, १; २. २५, १; ३. १, ४; १३; २, ७; २९, १३; ३१, ३; ५१, ८; ५४, ८; ५. २, २; ३२, ११; ६. ७, १; १६, ४०; ४२; ७. ३३, १३; ८. ६२, १०; ७०, ५; ८९, ६; १०३, १; ९. १८, २; ५५, २; ६१, १०; १३; १००, १; ७; १०. २२, ११; ५५, २; ७३, १०; ८८, १६; ९०, ७; १५३, १; १६२, ३; १६३, ६; १८३, १.
जातऽविद्यां १०. ७१, ११.
जातऽवेदः १. ४५, ३; ७८, १; ३. १५, ४; २९, ४; ५. ४, १०; ६. १६, २९; ३०; ३६; ८. ४३, २; ९. ६७, २७; १०. ५१, १.
जातऽवेदः १. ४४, १; ५९, ५; ७९, ४; २. २, १२; ३. ६, ६; १७, २–४; २०, ३; २१, १; २२, १; २५, ५; २८, १; ४; ६; ५७, ६; ४. ३, ८; ५, ११; १२; १२, १; ५. ४, ४; ९; ११; ४३, १०; ६. ५, ३; ७. ३, ८; ५, ७; ८; ९, ६; १३, २; १७, ३; १०४, १४; ८. ११, ३; ४; ७१, ७; १०. ४, ७; ८, ५; १५, १२; १३; १६, १; २; ४; ५; ५१, ३; ७; ६९, ८; ९; ८७, २; ५–७; ११; ८८, ५; ११०, १; १४०, ३.
जातऽवेदसः ३. ११, ८; ६. ८, १; ८. ११, ५; ४३, ६; १०. १८८, २; ३.
जातऽवेदसं १. ४४, ४; ५०, १; १२७, १[२]; २. २, १; ३. २, ८; ३, ८; ११, ४; ५. ९, १; २२, २; ६. १५, ७; ४८, १; ८. २३, १; १७; २२; ४३, २३; ७१, ११; ७४, ३; ५; १०. ६, ५; १६, १०; १५०, ३; १७६, २; १८८, १.
जातऽवेदसा ७. २, ७.
जातऽवेदसि ६. १६, ४२.
जातऽवेदसे १. ९४, १; ९९, १; ३. १०, ३; ५. ५, १; ७. १४, १; १०. ९१, १२; ११५, ६.
जातऽवेदाः १. ७७, ५; २. ४, १; ३. १, २०; ५, ४; २३, १; २६, ७; २९, २; ४. १, २०; १४, १; ५८, ८; ६. ४, २; १०, १; १२, ४; १५, १३; ७. ९, ४; १२, २; १७, ४; १०. १६, ९; ४५, १; ६१, १४; ८३, २; ८८, ४.
जातस्य १. ९६, ७; २. ३३, ३; ४. ७; १०; ८. २, २१.
जाता १. १८१, ४; ३. ३९, ३; ६. ६१, १२; ८. १, १८; ३९, ६; ८८, ४; ९. ८८, २.
जाताः १. २३, १२; १८४, ३; ३. ४, ५; ५. ५५, ३; ८७, २; १०. ७, २; ६३, २; ७२, ८; ८०, ६; ९०, १०; ९७, १.
जातान् ४. २, २.
जातानि १. १२८, ४; ५. ८२, ९; ६. २५, ५; ७. ८२, ५; ८. ४१, ७; ६२, २; ९६, ६; ९७, ९; १००, ४; १०. १५३, ५.
जातासः ९. १०६, १; १०. १२, ३.
जातासु ३. ५५, ५.
जातु १०. २७, ११.
जातूऽभर्मा १. १०३, ३.
जातूऽस्थिरस्य २. १३, ११.
जाते ३. ३१, १०; ४. ३, ११; ८. ९९, ३; १०. ८८, २; १३०, ६.
जाते इति १. १८५, १; ५. ४७, ५; ९. ९, ३.
जातेन २. २५, १; १०. ४५, १०.
जातेभिः ३. ३१, ११.
जातेषु ४. १८, ४.
जातैः ५. १५, २.
जातौ २. ४०, १; ५. ७३, ४; ७. ३३, १३.
जानत १. ६८, ४; ८. ७२, १४.
जानता ५. ५१, १५.
जानतां १०. १९१, २.
जानती १. १०४, ५; १२३, ९; १२४, १; ३. ३१, ६; ५. ४५, २.
जानतीः १. १४०, ७; ३. ३१, ४; ४. १, १६.
जानते ३. ५७, ३; ७. ७६, ५; १०. २०, ६; ७१, २.
जानन् १. १४०, ७; ३. २९, १०; ९. ७०, ६; ९६, ७.

जानंतः १. १५६, ३; १०. १२३, ४.
जानंति ३. ७, ५; १०. ११४, २.
जानंति ३. ३०, १३.
जानं १. ३७, ९; ५. ५३, १; १०. ३२, ३.
जानां १. ९५, ३; १०. ७२ १.
जानात् १०. १३९, ६.
जानाति ५. ६१, ७.
जानाति ४. ४, ६; ६. ९, ३.
जानामि १. १६४, ३७; ६. ९, २.
जानीत १. ९४, ८.
जानीथ ८. १८, १५.
जानीमः १०. ३४, ४.
जानीहि १. ५१, ८; ७. ५४, १.
जानु १०. १५, ६.
जां ९. ८९, २; १०. ३, २.
जामयः १. २३, १६; ३१, १०; ३. ५७, ३; ६. २५, ३; ८. १०२, १३; ९. २६, ५; ६५, १; ६६, ८; ८९, ४; १०. १०, १०.
जामयें ३. ३१, २.
जामर्येण ४. ३, ९.
जामातुः ८. २६, २१.
जामातरं ८. २६, २२.
जामाता ८. २, २०.
जामि ३. ५४, ९; ७. ७२, ३; ८. ६, ३; ७२, ४; १०. ८, ७; १०, ४.
जामिः १. ६५, ४; ७५, ३; ४; १२३, ५; ४. २५, ६; ९. १०१, १४.
जामिऽत्वं १. १६६, १३; १०. ५५, ४; ६४, १३.
जामिऽत्वाय १. १०५, ९.
जामिऽभिः १. ७१, ७; १००, ११; ८. ७२, १४; ९. २८, ४; ३७, ४; ६८, ४; ७२, ३.
जामिं १. १११, ३; १२४, ६; ३. २, ९; ४. ४, ५; ६. ४४, १७; ८. १२, ३१; ९. ९६, २२.
जामिऽवत् १०. २३, ७.
जामिषु १०. २१, ८.
जामी इति १. १५९, ४; १८५, ५.
जामीन् ६. १९, ८.
जामीनां ३. १, ११.

जाम्योः ५. १९, ४.
जायत १. १२८, १; ४. १, ११.
जायतां १. १०५, १५; १०. ४३, ९; ६२, ८.
जायते १. ३१, ११; ३. ४, ९; १०, ६; ३९, १; ६. ४८, ५; ७. ५०, ३; ९. ४७, ३; १०. ३९, १२; ८७, १३.
जायते २. ३, ९; ३. ८, ५; ४. ११, ४; ५. १, ४; ८३, ४; ६. ७, ३; ४८, २२; ७०, ३; ७. ९०, २; ९. ६८, ५; ७४, ४; १०. ४, ५; ५२, ३; ८५, १८; ८८, ६.
जायथाः ३. ४८, २; ८. ८९, ५.
जायंते २. ३५, ८; ३. ३६, ५; ४. ११, ३; ५. १९, १; ५८, ५.
जायमानः १. ९६, १; १४३, २; १६३, १; १६५, ९; ३. ६, २; ५; ८, ४; ४. १७, ७; १८, ५; २२, ३; ५०, ४; ६. ७, ५; ९, १; १०, ४; ४४, २२; ७. ५, ७; १३, २; ३६, ३; ६७, २; ९९, २; ८. ९६, १६; १०. ५९, ४; ९६, १०; १०. ७९, ४; ८५, १९.
जायमानं १. ६०, ३; १६४, ४; ६. ७, ४; ९. ११०, ८; १०. ८९, १३.
जायमानस्य १. ९६, ७; २. ९, ५.
जायमाना १. ९२, १०; ३. ३९, २; ६. ६७, ४; १०. ६१, १९.
जायमानाः ६. ५२, ४.
जायमानात् १. ९५, ५.
जायमानां ५. ४२, १३.
जायमाने ८. ७०, ४; १०. ९५, ७.
जायमानौ २. ४०, २.
जायवः १. ११९, ३; १३५, ८[२].
जायसे ५. ३, १.
जायसे १. १२७, ९; २. १, १; ५. ११, ३; ६; ८. ४३, ९.
जायस्व १०. १८३, १.
जाया १. १०५, २; ३. ५३, ४; ६; १०. १७, १; ३२, ३; ३४, ३; १०; १३; ८५, २९; १०९, ४.
जायाऽइव १. ६६, ३; १२४, ७; ९. ८२, ४; १०. १०, ७.

जायां १. ८२, ५; ११६, १; ११७, २०; ४. १८, १३; १०. ३४, २; ४; ११; ८५, २२; ३८; १०९, ५; १४९, ४.
जायुः १. ६७, १.
जायें १०. ९५, १.
जायेमहि १. ९७, ४; ४. २, १५.
जायेमहि २. ३३, १.
जारः १. ४६, ४; ६६, ४; ६९, १; ५; ११७, १८; १३४, ३; ६. ५५, ४; ५; ७. ९, १; १०, १; ९. ३८, ४; ९६, २३; १०१, १४; १०. ३, ३; ११, ६; १११, १०; १६२, ५.
जारःऽइव ७. ७६, ३.
जारे १०. १०६, ७.
जारं १. १५२, ४; ९. ५६, ३; १०. ७, ५; ४२, २; १२३, ५.
जारंऽइव ९. ३२, ५.
जारयत्ऽमखः १०. १७२, २.
जारयायि ६. १२, ४.
जारस्य १. ९२, ११.
जारिणींऽइव १०. ३४, ५.
जारिषुः १. १२५, ७; १३९, ८[२].
जार्यं ५. ६४, २.
जाऽवंतः ८. ९४, ५.
जासु ७. ४६, २.
जाहुषं १. ११६, २०; ७. ७१, ५.
जिगत्नवः ९. १०१, १२; १०. ७८, ३; ५.
जिगत्नु ७. ६५, १.
जिगत्नुं ९. ९७, १७.
जिगत्नू इति १०. १२०, ७.
जिगाति ५. २९, ४.
जिगात ९. ७१, ५.
जिगात १. ८५, ६; ७. ५७, ७.
जिगातन ५. ५९, ६.
जिगातं २. २४, १२.
जिगाति ५. ८७, ४; ७. ४, १; ७१, ४; १०४, १७; १०. १२३, ८.
जिगाति १. २, ३; ८७, ५; ३. ४, ३; १२, २; २७, १; ३९, १; ६२, १३; ६. ६, १; ७. ७५, ४; ८४,

१; ८. ४९, २; ९. १४, ६; ९६, ९; १०. ६, ४; ८, २; ४७, ६.

जिगातु ८. ४५, ३२.

जिगातु २. ३४, १५.

जिगार्य ३. ३४, ४; ५. ४५, ६; १०. १०२, ९.

जिगाय १. ३०, १६; ११६, २; ६. ३२, ३; १०. ६९, ११; १०२, ५.

जिगासि १०. ७३, ३.

जिगासि ३. २२, ३; ५. १५, ४.

जिगीवांसः २. १८, ८; ५. ६२, ९; ६. १९, ७; १०. ७८, ४.

जिगीवान् २. १२, ४.

जिगींपमाणं १. १६३, ७.

जिगींपसे १०. ४, ३.

जिगीपा १. १७१, ३; १८६, ४.

जिगीपुः २. ३८, ६.

जिगृत ७. ५७, ६.

जिगृतं १. १५८, २; ४. ५०, ११.

जिगेथ १. १०२, १०; ९. ६६, १६; १०. ६९, ६.

जिग्ययुः ६. ६९, ८.

जिग्युः ८. १९, १८; १०. ८७, १९; १०७, ९[४].

जिग्युऽर्भिः १. १०१, ६.

जिग्युर्पः १. १७, ७; ७. ३२, १२; ८. १४, ६; ८०, ६; ९. ६५, ९; १००, ४.

जिग्युर्षा ९. ४७, ५.

जिग्युर्पे ६. ४६, २; १०. १२७, ८.

जिग्ये १. ३२, १३; ६. ६९, ८; १०. ४८, ५.

जिघत्नुः २. ३०, ९.

जिघर्ति ४. १७, १४; ५. ४८, ३; १०. ६, ४.

जिघर्मि २. १०, ४.

जिघर्मि २. १०, ५; १०. ८७, १.

जिघांसतः १. ३६, १५; ८०, १३; ८. ६७, ११; १०. १०२, ३.

जिघांसति २. २३, १२; ६. १६, ३२; ७५, १९; ७. ५९, ८; १०. १३३, ३; १६२, ३.

जिघांसन् ४. २३, ७; ७. ८६, ४.

जिघांससि १. १७०, २.

जिघ्नते ७. ८३, ९.

जिघ्नते १. ५४, १०; ८०, ५; ६; ६. ५६, २; ५७, ३; ७५, १३; ८. १७, ८; २९, ४; ९. १, १०; १४, ४.

जिघ्नंते १. ६४, ११.

जिघ्नमानः ३. ३०, ४.

जिघ्नसे १. १०२, ७; ८. १५, ३; ४३, ३२; ९५, ९; ९. १००, ८.

जिजिन्वथुः १. ११२, ६.

जिज्यांसतः १०. १५२, ५.

जितं ८. ७६, ४.

जितं ९. ७, ९.

जितिं १०. ५३, ११.

जिनंति ४. २५, ५.

जिनाति ५. ३४, ५; ९. ५५, ४.

जिनामि १०. २७, ४.

जिनोपि ५. ८४, १.

जिन्व ३. १५, ६; ८. ६०, १२; ९. १०८, १०.

जिन्व २. २३, १९; २४, १६; ३. ३, ७; ५३, २१; ६. ३५, ५; ८. ३२, ७.

जिन्वत १०. ६६, १२.

जिन्वंत १. ११८, २.

जिन्वर्त १. १५७, २; ६. ४९, ६; ७. १०४, ६; ८. ३५, १६[२].

जिन्वति १. १६२, ३; ८. ४४, १६.

जिन्वतु २. ४०, ६; ४. ५३, ७; ६. ४९, १४; १०. ६६, ३.

जिन्वते ३. २, ११.

जिन्वथ ६. ४९, ११; ८. ७, २१; १०. ९, ३.

जिन्वथः १. ११२, २; ६; २२; ५. ७४, ४; ८. २२, ७.

जिन्वथुः २. ४०, ३; ४. ४५, ३.

जिन्वन् ९. १२, ६.

जिन्वन् १. ७१, १.

जिन्वंतः १. ६४, ८.

जिन्वंति १. १६४, ५१.

जिन्वंति १. १६४, ५१.

जिन्वसि ८. ८४, ७.

जिन्वे ४. २१, ८.

जिव्रयः ४. १९, २; ८. ४५, २०.

जिव्रिः १. १८०, ५.

जिव्रिं ८. ५१, २.

जिव्री इति १. ११०, ८; ४. ३६, ३; १०. ८५, २७.

जिव्रेः १. ७०, ५.

जिषे १. १११, ४; ११२, १२.

जिष्णुः १. १८१, ४; ७. ३५, ५; १०. १११, ३.

जिष्णुनां १०. १०३, २.

जिष्णुं १०. ६७, ९.

जिष्णो इति ६. ४५, १५.

जिष्णोः १. १२२, १५; ४. ३९, ६; ४०, १; ५. ४२, ६.

जिहृतां १०. ३५, ६; १४२, ६.

जिंहेत ५. ८३, ४.

जिहृते ५. ५७, ३; ६०, २; ६. १८, १५; ८. ७, ३४; ९. ५, ५.

जिहातां ७. ३४, २४.

जिहाते इति ३. ३१, १७; ५. ३२, ९.

जिहानः ३. ३८, १.

जिहींत १. ३७, ७; ५. ४५, ३.

जिहीतां १०. ५९, १.

जिहींते ८. २०, ६.

जिहीते १. १०५, १८; १६६, ५; ३. ५१, ४; ५. ३२, १०; ७. ७१, १.

जिहीळ १०. ८३, ५.

जिहीळानस्यं १. २५, २.

जिहीळिरे ७. ५८, ५.

जिहीळे १०. ३४, २.

जिहीष्व ५. ७८, ५.

जिह्मऽबारं १. ११६, ९; ८. ४०, ५.

जिह्मं १. ८५, ११.

जिह्मऽश्ये १. ११३, ५.

जिह्मानां १. ९५, ५; २. ३५, ९.

जिह्नर्या १. १४, ८; ४६, १०; १४०, २; १६८, ५; ३. ३५, ९; १०; ५. २६, १; ४८, ५; ५१, २; ६. १६, ३२; ५९, ६; ६०, १०; ६७, ८; ७. १६, ९; ८. १७, ५; ७२, ३; ४; १८; १०. ४, ४; ३७, १२; ४६, ८; ५३, ११; ७९, २; ८७, २.

जिह्वरः १०. १६, ८.
जिह्वा १. ८७, ५; ३. ५७, ५; ४. ५, १०; ५८, १; ६. ६, ५; ९. ७५, २; १०. ६८, ६; १३७, ७.
जिह्वाः ३. २०, २; १०. ७८, ३.
जिह्वाभिः ६. १६, २; ८. ४३, ८.
जिह्वां २. १, १३; ४, ४; ४. ७, १०; ६. ३, ४; १०. ८, ६; ५३, ३.
जिह्वायाः ३. ३९, ३; ९. ७३, ९; १०. १६३, १.
जीजनत् १. १२९, ११²; १०. ११५, १.
जीजनत् ४. १६, ३; ८. १२, १४.
जीजनन् १. १५१, १; ४. ६, ८; १०. ११, ३.
जीजनन्त १. ६०, ३.
जीजनन् ७. १५, ४.
जीमूतस्यऽइव ६. ७५, १.
जीयते ९. ५५, ४; १०. १५२, १.
जीयते ३. ५९, २; ५. ५४, ७.
जीरऽअध्वरं १०. ३६, ६.
जीरऽअश्वः १. १४१, १२; १५७, ३; २. ४, २.
जीरऽअश्वं १. ११९, १.
जीरः ३. ३, ६; ७. ९२, २.
जीरऽदानवः २. ३४, ४; ५. ५४, ९; ८. ५९, ४.
जीरऽदानवः ५. ५३, ५.
जीरऽदानवे १०. ४३, ८.
जीरऽदानुः ५. ८३, १; ८. ६२, ३.
जीरऽदानुं १. १६५, १५; १६६, १५; १६७, ११; १६८, १०; १६९, ८; १७१, ६; १७३, १३; १७४, १०; १७५, ६; १७६, ६; १७७, ५; १७८, ५; १८०, १०; १८१, ९; १८२, ८; १८३, ६; १८४, ६; १८५, ११; १८६, ११; १८९, ८; १९०, ८; ९. ९७, १७.
जीरदानू इति जीरऽदानू ५. ६२, ३; ७. ६४, २.
जीरदानो इति जीरऽदानो ९. ८७, ९.
जीरं १. ४४, ११; ५. ३१, १२.
जीरयः २. १७, ३; ३. ५१, ५.
जीराः १. १३५, ९; ७. ८१, ३; ९. ६६, २५.

जीरो ९. ६६, ९.
जीव १०. १६१, ४.
जीवः १. ११३, १६; १६४, ३०; ५. ४४, ५; ७८, ९².
जीवऽगृभः १०. ९७, ११.
जीवतः १०. १६४, १; २.
जीवति १. १६४, ४२; १०. ३३, ९.
जीवथः ६. ५९, १.
जीवऽधन्यं १०. ३६, ८.
जीवऽधन्याः १. ८०, ४; १०. ३०, १४; १६९, १.
जीवनं १. ४८, १०.
जीवनाय १०. १६१, १.
जीवन्तः १. १३६, ६; १०. ३७, ६.
जीवन्ति १. १६४, ४२.
जीवन्तु १०. १८, ४.
जीवन्त्याः ५. ७८, ९.
जीवपीतऽसर्गः १. १४९, २.
जीवऽपुत्राः १०. ३६, ९.
जीवं १. ९१, ९; ११३, ८; १४०, ८; १६४, ३०; ४. ५१, ५; ७. ७७, १; १०. ४०, १०; ५७, ५; ९७, १७; १०७, १.
जीवयन्थ १०. १३७, १.
जीवऽयाजं १. ३१, १५.
जीवऽलोकं १०. १८, ८.
जीवऽशंसे १. १०४, ६; ७. ४६, ४.
जीवसे १. ३६, १४; ३७, १५; ७२, ७; ७९, ९; ८९, २; ९१, ७; ११७, २४; ११९, १; १४६, ५; १५५, ४; १७२, ३; २. २८, ७; ३९, ६; ३. ३६, १०; ५३, १८; ६. ६९, ५; ७. ६२, ५; ८. ६, ३३; १८, १८; २२; ४८, ४; ६३, ९; ६७, १२; १७; ६८, १२; ९. ६६, ३०; ८२, ४; ८६, ३८; १०. १४, १४; १८, ६; २५, ४; ६; ३५, १२; ३६, ५; ५७, ४; ५८, १; १४४, ५; १८५, ३; १८६, ३.
जीवाः ७. ३२, २६; १०. १८, ३; ३६, ९; ३७, ७; ८.
जीवात् १. ८४, १६.
जीवातवे १. ९४, ४; १०. ५९, ५; ६०, ८; १७६, ४; १८६, २.

जीवाति १०. ८५, ३९.
जीवातुः १०. २७, २४; ६०, ७.
जीवातुं १. ९१, ६; ६. ४७, १०; ८. ४७, ४.
जीवान् २. २८, ९; ८. ६७, ५.
जीवाभिः १०. १९, ६.
जीविता १. ११३, ६; ४. ५४, २.
जीवेत् १०. ३३, ८.
जीवेभ्यः ८. ८, २३; १०. १८, ४.
जीवेम ७. ६६, १६.
जीहिपः ३. ५३, १९.
जुगुपुः ७. १०३, ९.
जुगुरत् ८. ८१, ५.
जुगुर्याः १. १४०, १३.
जुगुर्यात् १. १७३, २.
जुगुर्वणी इति १. १४२, ८.
जुघुक्षतः ८. ३१, ७.
जुजुरुषः १. ११६, १०; ५. ७४, ५.
जुजुर्वान् १. १५८, ६; २. ४, ५.
जुजुर्वान्ऽइव १. ३७, ८.
जुजुषन् ७. ६१, ६.
जुजुषाणः १. ९१, १०; २. ३६, ३; ४. ६, ४; ८. ६६, ८.
जुजुषाणं ७. २३, ३.
जुजुषाणा १. ११८, ७; २. ३९, ८; ५. ४३, ११; ७. ६८, १.
जुजुषाणाय ५. ४३, ५.
जुजुषाणासः ४. ३४, ३.
जुजुषुः ९. ७७, ३.
जुजुषुः १. १५२, ५; १६५, २; ८. २३, ९.
जुजुषे ४. २२, १; १०. ६१, २५.
जुजुषे ५. ३९, ४.
जुजुष्टन ४. ३६, ७; ७. ५९, ९.
जुजुष्वान् २. २०, ५; ८. ६४, ८.
जुजोष ६. १४, १.
जुजोष ४. २३, ५; २४, ५; २५, १.
जुजोषः ४. २, १०; ९, ६; ५. ३०, ३; १०. ८, ५.
जुजोषत् १. १७३, ४; ३. ४, ६; ४. ४, १०; २३, ४; ७. २६, १; ८. ९६, १२.
जुजोषत ७. १०१, ५.
जुजोषतं १. ९३, ११.
जुजोषति ८. ६२, १.

जुजोषति १०. ३२, १.
जुजोषते ९. १०३, १.
जुजोषथ १०. ६३, ६.
जुजोषथः ७. ८२, ८.
जुजोषन् ७. ५८, ३.
जुजोषसि ८. ५२, १.
जुनंति ५. ५८, ३; ७. २०, १०; ४०, ३; ६७, ९.
जुनंति १. १६९, ३; ७. ५६, २०; १०. ५२, २.
जुनाः १. २७, ७.
जुनाति ७. ८६, ७.
जुनामि १. १८६, ५.
जुनासि १. ७१, ६.
जुनीमसि ९. ७९, २.
जुरतं १. १८२, ३.
जुरतां २. ३४, १०.
जुरते ७. ६८, ६.
जुर्वः १. १३४, १; १४०, ४; ९. ६५, १८.
जुषत् १०. २०, ५.
जुषत १. २५, १८; ५. १३, ३; ७. १५, ६.
जुषतां १०. १६५, २.
जुषध्वं ५. ५५, १०; १०. १५, ४.
जुषध्वं १. १३९, ११; ५. ५८, ३; ७. ५६, १४; १०. ५३, ४.
जुषंत १. १४८, २; १६७, ४; ७. ५, ६; ११, ४; ५६, २०; ८. १३, ६; ९. १०२, ५.
जुषंत १. ३, ९; ६८, २; ५; १२७, ६; २. २७, २; ४०, २; ५. ४१, २; ४६, २; ६. १६, ८; ५२, ११; ७. ३४, २५; ३५, १४; ५२, ३; ५८, ६; ६४, १; ८. १३, २९; ९. ८१, ५; १०. ८, ३; ७०, ८.
जुषंतां ३. २२, ४; ६. ५२, १०.
जुषंतां १०. ५३, ५.
जुषमाणः ४. २३, १.
जुषस्व १. ७५, १; १४४, ७; २. ३२, ६; ४१, १८; ३. २४, २; २८, १; ६; ३९, ७; ५१, ६; ५२, २; ६२, ४; ५. ४, ४[२]; ६. २, १०; ६१, १४; ७. २, १; ८. ६, ३२.
जुषस्व १. १२, १२; १०१, १०; ३. १, १; १४, २; १५, २; २१, १; ४; २८, २; ४; ३३, ८; ३५, १०; ४०, ८; ५२, १; ४; ६१, १; ६२, ८; ४. २, २०; ३, १५; ५. ४, ८; ८, ४; २९, १५; ६. ५, ६; ४७, १०; ७. २२, ३; ४२, ५; ५४, १; २; ९५, ५; ९९, ७; ८. १२, ५; ४३, १६; ४४, २; ५; ९०, ३; १०२, २०; १०. १५, १३; ६९, ३; ४; ७०, १; १२२, ३.
जुषाणः १. १३५, २; २. १४, ९; ३. ३२, ५; ४३, ४; ४४, १; ४. २३, १; ५८, ८; ५. ५१, ५; ६. ४७, २८; ७. ७, २; १४, ३; २४, ४; २९, २; ९८, २; ८. १३, १३; ४४, ८; ४८, २; ६५, ८; ७२, २; ९. ९७, ११; १०. ६, ४; ६९, १०; १२२, २; १६०, २; १७९, ३.
जुषाणा १. ११८, १०; ३. ५८, ७; ५. ७५, ३; ७. ३८, ४; ९५, ४; ८. ५७, २.
जुषाणाः १. १७१, २; ३. ४३, २.
जुषाणौ ७. ६६, १९.
जुषाते ४. ४३, १.
जुषेत १. १३१, ६.
जुषेत २. १०, ५; ७. ३४, २१; ८६, २.
जुषेतां ५. ७२, ३.
जुषेथां १. ९३, ७; २. ३६, ६; ५. ७८, ३; ६. ६९, १; ४; ७. ९३, १; ८. ३५, ४; ३८, ४; ६.
जुषेथां ४. ५७, ५; ५. ५१, ६; ७. ७०, ७; ७३, ३; ८. ३५, ५; ६[२]; ३८, ५.
जुषेरत १. १३६, ४; १०. ६५, १४.
जुष्टः १. ४४, २; ५. ४, ५; १३, ४; ९. ९, २; १३, ८; ७०, ८; ९७, १९; १०८, १६.
जुष्टः ९. ४४, २.
जुष्टऽतमः १. १६३, १३.
जुष्टऽतमासः १. ८७, १.
जुष्टऽतरस्य ८. ९६, ११.
जुष्टं १. ४४, ४; ३. ५३, ३; ५९, ५; ७. ९७, ५; ८. ४४, ७; ८७, ३; ८९, ७; ९. ९७, २२; १०. ८८, १; १२५, ५.
जुष्टयः १. १०, १२.
जुष्टाः १. १०, १२; १८२, ६; ५. ३३, १०.
जुष्टानि १. ७३, १०.
जुष्टा १. ३३, २; ४. २९, ३.
जुष्टासः ४. ३७, २.
जुष्टिं १०. ११४, १.
जुष्टी ७. ३३, ४.
जुष्ट्वी १. ११८, ५; ८. ६२, ६; ९. ९७, १६.
जुहुवाम १. ११०, ६; ११४, ३.
जुहाव ७. २१, ८; ८. ९, १०.
जुहुऽआस्यः १. १२, ६.
जुहुत ७. १५, १; १०. १४, १३.
जुहुते ६. १९, ६.
जुहुमः ५. ७२, १.
जुहुयाम ७. १, १७.
जुहुरः ७. ४, ४.
जुहुरंत १. ४३, ८; ३. ५५, २.
जुहुराणः १. १७३, ११; ४. १७, १४; १०. १२, ५.
जुहुराणं १. १८९, १.
जुहुराणा ८. २६, ५.
जुहुरे ५. १९, २.
जुहुरे २. ९, ३.
जुहूभिः १. ५८, ४; ५. १, ३; १०. २१, ३.
जुहूमसि १. ४, १; ८. ५२, ४.
जुहूरे १. ४८, १४; ८. ८, ६.
जुहूर्थाः ७. १, १९.
जुहोत १. १५, ९; २. १४, १; ७. १०२, ३.
जुहोत २. १४, ५; ८; ९; ३. ९, ८; ५९, १; ५; ५. २८, ६; ७. ४७, ३.
जुहोतन ७. ९८, १; १०. १७९, १.
जुहोतन २. ३२, ७; ५. ५, १; ८. ४४, १; १०. १४, ५.
जुहोति १०. ७९, ५.
जुहोति १०. ९१, ४.

जुहोमि ३. १८, ३; १०. ८३, ७.
जुहोमि १. १६२, १९; २. २७, १; १०. १७, ११; १२; १९१, ३.
जुह्वः १. ५८, ७; १४५, ३; ६. ६६, १०; ८. ४३, १०; ४४, ५.
जुह्वत् ७. ८५, १; १०. ८१, १.
जुह्वतः ८. २७, २२.
जुह्वति २. ४१, १८; ५. ७, ५.
जुह्वते १०. ४०, ४.
जुह्वं १०. ६, ५; १०९, ५.
जुह्वा १. ६१, ५; ७६, ५; २. १०, ६; २७, १; ३. ३१, ३; ४. ४, ३; ६. ११, २; ७. ३, ४; १०. ६, ४; ११५, २.
जुह्वानः १. ७५, १; ८. २३, ६.
जुह्वाना ८. ९५, ५.
जुह्वानाय ८. २७, २१.
जुह्वानासः ८. ७४, ६.
जुह्वे ४. ३७, ३; ६. २, ३; १०. १४९, ५.
जुह्वे ८. ३९, ३.
जूः २. १४, ३.
जूजुवत् २. ३१, ४.
जूजुऽवांसः ५. ३१, ११.
जूजुऽवान् ४. ११, ४.
जूजुवानस्य १०. ९३, ८.
जूजुवानेभिः ५. २९, ९.
जूजुवुः ७. २१, ५.
जूतः ४. १७, १२; ९. ९७, ५२.
जूतये १. १२७, २.
जूताः ९. ६४, १६.
जूतिऽभिः १. ११६, २; ३. ३, ८.
जूतिं ३. ३४, २; ४. ३८, ९; ९. ९७, ९.
जूती ८. ४१, ६.
जूत्या ३. १२, ३.
जूर्णः १. १८०, ५.
जूर्णाऽइव १. १८४, ३.
जूर्णा ९. ८६, ४४.
जूर्णायां १. ४६, ३.
जूर्णिः १. १२७, १०.
जूर्णिः १. १२९, ८; ७. ३९, १; ८. ७२, ९.
जूर्णिनीं ६. ६३, ४.
जूर्यः ६. २, ७.
जूर्यति १. १२८, २.
जूर्यत्ऽसु ३. २३, १.
जूर्यंति १. ११७, ४.
जूर्यत्यै १. ११७, ७.
जूर्वे ६. ६, ६.
जूर्वन् १. १९१, ९.
जेः ६. ४, ४.
जेता १. ६६, २; १७८, ३; २. ४१, १२; ४. २०, ५; ६. ४५, २; ९. ९०, ३; १०. ५५, ६; १०७, ११.
जेतारं १. ११, २; ५. २५, ६; ८. ९९, ७.
जेत्वानि ६. ४७, २६.
जेन्यः १. ७१, ४; १२८, ७; १४०, २; १४६, ५; २. १८, २; ५. १, ५.
जेन्यं १. १३०, ६; २. ५, १; ८. १०१, ६; ९. ८६, ३६; १०. ४, ३.
जेन्यस्य ६. ४२, ४; १०. ६१, २४.
जेन्या १. ११९, ५; ३. ३१, ११.
जेन्याऽवसू इति ७. ७४, ३; ८. ३८, ७.
जेमना १०. १०६, ६.
जेषः १. १०, ८.
जेषत् ८. ४०, १०.
जेषाम ८. ६३, ११; ९. ७६, ५.
जेषि ६. ४५, १५; ९. ४, १.
जेषि १. १३२, ४; २. ३०, ८; ९; ३. ५४, २२; ९. ४४, ६.
जेषे १. १००, ११; ६. ४४, १८.
जेष्मं ७. १८, १३.
जेष्म ६. ४५, १२; १०. १५६, १.
जेष्यामि १०. ३४, ६.
जेहमानं १. ११०, ५; १६३, ६.
जेहमानस्य १०. ३, ६.
जेहमानाः १०. १५, ९.
जैत्रे १. १०२, ३; ५; १०. ३६, १०; १०३, ५.
जैत्रस्य ९. १०६, २.
जैत्रा ८. १५, ३.
जैत्राय ८. १५, १३; ९. १११, ३.
जैत्रीः ३. ३१, ४.
जैत्री १. १११, ३.
जोगुवानः १. ६१, १४.
जोगुवां १०. ५३, ६.
जोगुवे १०. १२७, १०; ५. ६४, २.
जोष १०. १५८, २.
जोषत् १. १६७, ५.
जोषत् १०. ८१, ७.
जोषति १०. १०५, ८.
जोषं १. ७७, ५; ११३, १०; २. २१, ३; ३०, २; ३७, १; ४. २७, २; ५. ३३, २; ६. २३, ८; ६४, ५; ६६, ४; ७. ४३, ४; ८. १९, २८; ९४, ६; ९. ७२, ३; १०. ९६, ७.
जोषयन्ते १. ८३, २.
जोषयासे ३. ५२, ३; ४. ३२, १६; ५. ३, १०.
जोषयेते इति १. ९५, ५; ६.
जोषऽवाकं ६. ५९, ४.
जोषि २. ३७, ६[४].
जोषि ४. ९, ७.
जोषिषत् २. ३५, १.
जोषे १. १२०, १.
जोष्टारःऽइव ४. ४१, ९.
जोष्या १. १७३, ८.
जोहवीति ७. ३८, ६.
जोहवीति ३. ३३, ४; ६२, २; ५. ४३, १; ७. ४१, ५; ५६, १८.
जोहवीमि ३. ४३, ३; ४. ४, १०; ७. ९३, १.
जोहवीमि १. ३४, १२; १६४, ५२; १७५, ६; १७६, ६; २. १०, ६; ५. ६९, ३; ६. ४०, ३; ७. २९, ४; ८. ९७, १३.
जोहुवत् ९. ६६, २९.
जोहुवतः ७. ९३, ३.
जोहुवती ७. २४, २.
जोहुवंत ७. २१, ७.
जोहुवानं ५. ४२, ७.
जोहुवाना ५. ४७, १.
जोहुवानान् ७. २८, ३.
जोहुत्रः २. १०, १; २०, ३.
जोहुत्रं १. ११८, ९.
ज्ञातयः ७. ५५, ५; १०. ६६, १४; ८५, २८.

ज्ञाती इर्ति १०. ११७, ९.

ज्ञायंते ४. ५१, ६.

ज्ञासः १. १०९, १.

ज्ञुःऽबाधं ६. १, ६.

ज्ञेयाः २. १०, ६.

ज्मः १. १५७, १; ४. ५०, १; ६. ६२, १; ८. १, १८; १०. ८९, १; ११.

ज्मन् ७. २१, ६; ६०, २.

ज्मयाः ७. ३९, ३.

ज्मा ६. ५२, १५.

ज्मायंतं ८. ६८, ३.

ज्यया १०. १६६, ३.

ज्या ६. ७५, ३.

ज्याकाः १०. १३३, १.

ज्यां ४. २७, ३.

ज्यायः ६. २६, ७; ७. ३२, २४; ९. ४८, ५.

ज्यायसः १. २७, १३.

ज्यायस्यै १. १२४, ८.

ज्यायांसं ५. ४४, ८.

ज्यायाः ६. ७५, १४; १०. ५१, ६.

ज्यायान् ३. ३८, ५; ४. ३०, १; ६. ३०, ४; ७. २०, ७; ८६, ६; १०. ५०, ५; ९०, ३.

ज्याऽवाजं ३. ५३, २४.

ज्येष्ठः १. १००, ४; ८. ७०, १; १०२, ११; ९. ६६, १६; १०. ५०, ४; १८०, १.

ज्येष्ठः ४. ३३, ५; १०. ११, २.

ज्येष्ठऽतमा ६. ६७, १.

ज्येष्ठऽतमाय २. १६, १.

ज्येष्ठऽतार्ति ५. ४४, १.

ज्येष्ठं १. ८४, ४; ५; १२७, २; १३६, १; २. ३५, ९; ३८, ५; ४. १, २; ५. ४९, २; ६. ४६, ५; ४८, २१; ७. ४३, ४; ६५, १; ८६, ४; ९७, ३; ८. ४, ४; ४६, १९; ५३, १; ७४, ४; १०. १२०, १; १२४, ८.

ज्येष्ठऽराजं २. २३, १; ८. १६, ३.

ज्येष्ठस्य ९. ९७, २२.

ज्येष्ठा ४. २२, ९.

ज्येष्ठाः १०. ७८, २.

ज्येष्ठाभिः ८. २३, २३.

ज्येष्ठासः ५. ८७, ९; १०. ७८, ५.

ज्येष्ठे २. १८, ८.

ज्येष्ठे इर्ति ४. ५६, १.

ज्येष्ठेन ८. २, २३.

ज्येष्ठेभिः १. १६७, २; १०. ३, ५; ६, १; ६१, १७.

ज्यैष्ठ्याय १. ५, ६; ३. ५०, ३.

ज्योक् १. २३, २१; ३३, १५; १३६, ६; २. ३०, १०; ४. २५, ४; ६. १५, १; २८, ३; ७. २२, ६; ९. ४, ६; ९१, ६; १०. ३७, ७; ५९, ६; १२४, १.

ज्योतिः १. ३६, १९; ४८, ८; ५०, १०[२]; ५७, ३; ५९, २; ६९, १; ८६, १०; ९२, ४; १७; ९३, ४; १००, ८; ११३, १; १६; ११७, १७; २१; १२४, १; ३; १८२, ३; २. ११, १८; २७, ११; १४; ३. २६, ८; ३०, १४; ३१, ४; ३४, ४; ३९, ७; ८; ४. १, १४; १०, ३; १६, ४; २५, ३; ५१, १; ५. ६३, ४; ८०, २; ६; ६. ३, १; ९, ४–६; ४४, २३; ४७, ८; ७. ५, ६; ३२, २६; ३३, ८; १०; ७६, १; ४; ७७, १; ७८, ३; ७९, २; ८१, १; ८२, १०; ९०, ४; १०१, २; ८. ६, ३०; १२, ३०; १६, १०; २४, २१; २५, १९; ४८, ३; ७३, १६; ८९, १; १०१, १२; ९. ४, २; २९, २; ३५, १; ६१, १६; १८; ६६, २४; ८६, १०; ९२, ५; ९४, ५; ९७, ४१; १०७, २६; ११३, ७; १०. १२, ७; ३५, १; ५; ३६, ३; ३७, ८; ४३, ४; ८; ५४, ६; ५५, २; ५६, २; ६७, ४; १०; ६८, ११; १०७, १; ११०, ७; १३६, १; १३९, १; १५६, ४; १७०, २; १८५, ३.

ज्योतिःऽअग्राः ७. ३३, ७; १०१, १.

ज्योतिःऽअनीकः ७. ३५, ४.

ज्योतिःऽकृत् १. ५०, ४.

ज्योतिःऽकृतः १०. ६६, १.

ज्योतिःऽजरायुः १०. १२३, १.

ज्योतिःऽरथः ९. ८६, ४५.

ज्योतिःऽरथं १. १४०, १.

ज्योतिःऽरथाः १०. ६३, ४.

ज्योतिषः १. २३, ५; २. २८, ७; ४. ५०, ४; १०. ६६, २.

ज्योतिषा १. ३३, १०; ९१, २२; २. १७, ४; २३, २; ३४, १२; ३. २, ३; ४. १३, १; १४, ३; ३८, १०; ५२, ६; ५. २, ९; १४, ४; ३१, ३; ८०, ५; ६. ८, ३; ९, १; ७२, २; ७. ७८, २; ८०, २; ८. ९८, ३; ९. ९७, ३९; १०८, १२; १०. १, १; ३५, ६; ३७, ३; ४; ४३, ९; ५५, ३; ५६, १; ६८, ५; ८७, १२; १२७, २; १७८, ३.

ज्योतिषां १. ११३, १.

ज्योतिषि १०. ५४, ६.

ज्योतिष्मत् १. १३६, ३.

ज्योतिष्मतः १०. ५३, ६.

ज्योतिष्मता ७. ७८, १.

ज्योतिष्मती १. ४६, ६.

ज्योतिष्मतीं १. १३६, ३.

ज्योतिष्मंतः ९. ११३, ९; १०. ७७, ५.

ज्योतिष्मंतं २. २३, २; ८. ५८, ३.

ज्योतींषि १. ५५, ६; ३. १०, ५; ८. १५, ५; ४४, १७; ६२, १२; ९. ३६, ३; ८६, २९; ९१, ६.

ज्रयः १. ९५, ९; १०१, ७; १४०, ९; ४. ५२, ५; ५. ४४, ६; ८. ३६, १; ९. ६८, २; १०. ९२, ५.

ज्रयति ९. ७१, ५.

ज्रयसः ५. ३२, ९.

ज्रयसानस्य १०. ११५, ४.

ज्रयसानौ ५. ६६, ५.

ज्रयांसि ५. ८, ७; ६. ६, ६; ८. २, ३३; १०. ७५, ७.

झ

ञ

ट

ठ

ड

ढ

ण

त

तु इतिं ते ३. ३३, १०.
तंसयेथे इतिं १०. १०६, १.
तकत् १. १३३, ४.
तकं १. १९१, १५.
तर्कवानस्य १. १२०, ६.
तर्कवे ९. ९७, ५२.
तक्तः ६. ३२, ५; ९. ३२, ४; ६७, १५.
तक्ति ९. १६, १.
तक्कः ८. ६९, १३.
तक्कवीःऽइंव १. १५१, ५; १०. ९१, २.
तक्कऽवीयें १. १३४, ५.
तक्का १. ६६, १.
तक्षत् १. ५१, १०; १२१, ३; १२७, ४; ६. १२, ५; ७. ६४, ४; ९. ९७, २२; १०. ९९, १.
तक्षत् १. ६१, ६.
तक्षत १. १११, २; ३; ३. ३८, २; ५४, १७; ४. ३५, ६; ३६, ८; ९; १०. १०१, १०.
तक्षतं ७. १०४, ४.
तक्षति १. १६२, ६.
तक्षती १. १६४, ४१.
तक्षथ ४. ३६, ३; १०. ५३, १०.
तक्षथुः १०. ३९, ४.
तक्षन् १. २०, ३^{२}; १११, १^{४}.
तक्षन् ५. ३१, ४.
तक्षंतु ४. ३३, ८.
तक्षं ६. ३२, १.
तक्षां ९. ११२, १.
तक्षाम ५. ७३, १०.
तक्षुः २. १९, ८.
तक्ष्यां ८. १०२, ८.
तत् १. १, ६; १०, २; २२, २०; २१; २४, ११^{२}; १२^{३}; २५, ६; २७, १०; ३०, ४; १२; ३१, १४; ३२, ११; १२; ३५, ६; ४२, ५; ४३, ४; ४८, ४; ५७, ४; ६२, ६; ६९, ४; ८०, १०; ८४, ९; १४; ८६, ९; ८९, ४^{५}; ९२, १३; ९३, ४; ९४, ८; ११; १४; १६; ९५, ११; ९६, ९; ९८, ३^{२}; १००, १९; १०१, ११; १०२, ११; १०३, १; ४; ५; ७; ८; १०५, ४^{२}; ९; १२; १७; १९; १०६, ५; ७; १०७, ३^{६}; १०८, १३; १०९, ८; ११०, १; ३; ९; १११, २; ५; ११२, २५; ११३, ९; १७; २०; ११४, २; ११; ११५, ४^{२}; ५; ६; ११६, २; ५; ६; ११–१३; ११७, ६; ८; १२१, १०; १२२, ३; १४; १२३, ११; १२९, ३^{२}; ६; ७; १३२, ३^{२}; १३३, ४; १३५, ८; १३६, ७; १३९, १; ८; १४१, १; १४२, १०; १४४, ३; ७; १५२, ३; १५४, २; ५; ६; १५९, २; ५; १६१, २^{२}; ४; ८; ११; १३; १६२, १०, ११^{२}; १६४, ११; २२; २३; २६; ३९^{२}; ४२; ४८; १६५, ३; १६६, १; १२^{२}; १३; १४; १६७, १०; १७०, १; १७३, १; १७९, ५; १८०, ४; १८२, ८; १८५, ३; १०; १९१, १६; २. ४, ९; ५, २; ३; १०, ५; ११, १९; १३, १^{२}; ३; १३; १४, १; ८; ११; १२; १७, १; १९, ७; २३, ४; १४; १५; १९; २४, ३; ६; ८; १६; २७, ८; ३२, २; ३४, १०; ३५, ११; १५; ३८, ११; ३९, १; ३. ४, ९; ५, ६; ९, २; ७; १२, ९; १४, ७; ३०, १२; ३२, ९; ३३, ७; ३६, ९; ३८, ४; ७; ३९, ५; ४८, २; ५३, ४; ५४, ९; १७; ५७, १; ६२, ३; १०; ४. १, १४; १६; ३, ५; ४, ११; १०, ६; ११, २; २०, ९; १०; २२, १; २७, ४; २८, १; ५; ३०, १९; ३३; ३३, ५; ३५, ९; ३६, १; ३; ४; ४३, ६; ५१, ११^{२}; ५३, १^{२}; ५४, ४^{२}; ५५, १०; ५८, ९; ५. ३, १०; १२; २५, ७; २९, ३; ३०, १; ३१, ७; ३५, २; ३९, १; २; ४७, ७^{२}; ४९, ४^{२}; ५३, १३; ५४, ५; १५; ५५, ७; ५६, २; ६२, १; २; ६६, ५; ६७, ५; ७३, ४; ७४, १; ८२, १; ५; ८५, ७; ८७, २^{२}; ६. ५, ६^{२}; १७, ६; १८, ३^{२}; ५; १३; १५; २०, ७; २१, ७; २२, ४; २३, ५; २६, ५; ७; ३०, ३; ४; ३४, ३; ३५, २; ४४, ६; ४५, २२; ३३; ४६, ८; ४७, १०; १८; ४८, २२; ४९, १४^{४}; ५१, ७; ५२, १; ५६, ४; ६२, ८; ६५, २; ६६, १; ६७, ८; ६९, ५; ८; ७२, १; ७. १६, ४; १८, १७; ३२; २४; ३३, १०; ३४, २३^{३}; २४; २५; ३८, ६; ४०, २; ५०, २; ३; ५२, २; ३; ५४, १; ५८, ४; ५; ५९, ९; ६६, १२; १६; ७०, १; ८१, ५^{२}; ८६, २–४; ९३, ७; ९४, ९; ९९, ७; १००, ५; १०१, ५; ६; १०३, ५; ७; १०४, ३; १२; ८. ३, ९^{२}; १०; २०; ४, ४; १६; १७; ६, ५; ९, २; १३; १३, ५; २०^{२}; १५, ६; १८, १२; १८; १९, १५; १६; २०, १४^{२}; २४, ११; २५; २५, १३; १४^{२}; २१; २७, २०; २२; २८, ४; ३२, ३; ३३, १७; ४०, ६; ४१, ४; ४३, १०; ३३; ४५, ६^{२}; २७; ३१; ४०; ४६, २८^{२}; ४७, ३; १०; १३; १४; १८; ५७, ३; ५९, ३; ६१, ६; १३; ६२, ३; ८; ९; ६३, ३; १०; ६५, ८; ६६, ५; ६७, १९; ६९, १३; ७२, १७; ८०, ९; ८३, १; ८८, ३; ८९, ५^{२}; ६^{३}; ९२, ५; ३१; ९३, ४; ५; ९६, २; १२; ९७, १५; ९९, २; १०२, २१; ९. १, ५; १९, १; ६७, २१; ७३, ९; ८३, १^{२}; ९२,

५; ९६, ४^{२}; ९७, ४१; १०१, १३; १११, २; १०. २, ३–५; १०, ४; १२, ३; १६, ६; १७, २; २२, ७; २७, १८; २१; २८, ८; ३०, १२; ३२, ३; ४; ३४, १२; १३; ३५, ८; १२; ३६, २; ९; १०; ३७, १; ६; १०–१२; ३८, २; ३९, २; ४०, ९; ११^{२}; ४३, ५; ४७, ८^{२}; ४९, १०; ५१, १^{२}; ५३, ४; ५५, १; ६; ५८, १; ६१, ५; १३; १८; २४; ६२, ४; ६७, ११; ६८, ८; ६९, ३; ७१, १; ७२, ३^{२}; ७३, ९; ७४, ४; ६; ७६, २; ३; ७९, ४; ८१, ४; ८५, १४; १६; ८७, १२; ९०, १२; ९२, १३; ९३, १४; ९४, १३; ९५, ५; ११; १३; ९७, ४; १०३, २^{२}; १०६, १; १०८, २; ११२, ४; ११४, ८; ११७, ४; १२०, १; ७; १२४, ४; १२६, २; १२९, २–४; १३५, ५; १३९, ४^{२}; ५; १४३, ४; १४४, ६; १५५, ३; १५९, १; ४; १७९, ३.

तर्तः १. ८३, ५; १६४, २५; ४२; १९१, १५; ३. ३७, ११; ७. २७, ३; ३३, १३^{२}; ८. ५, १९; ६१, १३; ९७, ३; १०. २७, २२; ८५, ५; ८८, ६; ९०, ४; ९७, १२; १२१, ७; १२५, ७; १३५, ६; १८६, ३; १९०, १^{२}.

ततः ९. ११२, ३; १०. १३०, १.

ततक्षं १. ५२, ७; ३. ८, ६; ६. ३, ८; १०. १०५, ६.

ततक्ष १. ३२, २; १२१, १२.

ततक्षिरे १०. ९२, ७.

ततक्षुः १. २०, २; ४. ३४, ९.

ततक्षुः ४. ५८, ४; ८. ९७, १०; १०. ५, ६; ४६, ९; ४८, ११; ८०, ७.

ततक्षे ५. ३३, ४.

ततनः १. ३८, १४; ७. २, १.

ततनंत् ८. २१, १८.

ततनंन् १. १६६, १४; ७. ८८, ४; १०. ३७, २.

ततनन् ४. ५, १३.

ततनंत १. ५२, ११.

ततनांम १. १६०, ५; ५. ५४, १५.

ततनुष्टिं ५. ३४, ३.

ततने ७. २९, ३.

ततंथ ६. १, ११; ४, ६; १०. १, ७.

ततंथ १. ९१, २२; ३. ६, ५; ६. ६, ६; १६, २१; ७. ५, ४; ८. ४८, १३.

ततऽअंन्नाय ८. ४७, १६.

ततन्युः १. १४१, १३.

ततन्वत् ६. २१, ३.

ततन्वान् ७. ६१, १.

ततपं ७. १०४, १५.

ततऽअंपः ५. ४७, २.

ततपंते ४. २, ६.

ततऽअंपसे ८. ४७, १६.

ततऽअंपाः २. १३, ३; ३८, १.

ततं १. ११०, १; २. ३, ६; ७. ३३, ९; ९. २२, ७; ६९, ६.

ततरुर्यः ६. १२, २.

ततर्द १. ३२, १; ४. २३, ८.

ततर्दिंय ९. ११०, ५.

ततस्यं ८. ९१, ५; ६.

ततस्ने ४. २३, ५; ५०, २; १०. ८९, १५.

ततस्ने १. १३१, ३.

तताः २. ५, २.

ततानं ५. १, ७; ७. २३, १; १०. ८८, १२; १७८, ३.

ततान १. ३५, ७; १०५, १२; १२६, २; ३. ५३, १५; ४. ३८, १०; ५. ५४, ५; ७६, ३; ८५, २; ६. १२, १; १०. ८०, ४; १११, ४.

ततापं १०. ३४, ११.

ततार ७. ३३, ३.

तर्तुरिः १. १४५, ३; ६. २४, २; ६८, ७.

तर्तुरिं ४. ३९, २; ६. २२, २.

ततृदाना ४. २८, ५.

ततृदानाः ५. ५३, ७.

ततृपि ३. ४०, २.

ततृषाणः १. ३१, ७; १३०, २; २. ४, ६; ६. १५, ५.

ततृषाणं १. १३०, ८; १७३, ११.

ततृषाणा १०. ९५, १६.

ततृषुः १०. १५, ९.

तते १०. १३०, १.

तते १. ८३, ५.

ततऽओंकसः १. १५, १.

ततऽओंकसा ४. ४९, ६.

ततऽओंकसे ३. ३५, ७.

ततओंकाः ७. २९, १.

ततऽओंजाः ५. १, ८.

ततऽतंत् १. ४६, १२; १५५, ४; ८. ३९, ४.

तत्निरे १. १६४, ५.

तत्निषे ८. ६, २५; ९. १०८, ६.

तत्ले १०. १३०, २.

ततऽबंधुः १०. ६१, १८.

तत्रं १. ९, ६; १३, १२; १०५, ९; १३५, ७; १७०, ४; ५. ५, १०; ६. १६, १७; ५७, ४; ७५, ८; ११; १७; ७. ८३, २; ८. ५८, १; ९. ११३, ८; १०. १६, ३; १७, ४; ३४, १३^{२}; ६४, १३.

तत्रे १०. १३२, ७^{२}.

तत्रो इतिं १. ३७, १४; ८. ५६, ४.

ततऽवुशः २. ३७, १.

ततऽवुशार्य २. १४, २.

तत्सार १. १४५, ४.

ततऽसिंनाय १. ६१, ४.

तर्था १. ३०, १२; १३६, ४; १६२, १९; ६. ५२, ५; ७. ५५, ६; ८. २०, १७; २८, ४; ३६, ७; ६१, ४; १०. ३३, ९; ९०, १४; १०८, २; १०९, ३.

तदानीं १०. १२९, १.

तदित्ऽअर्थाः ८. २, १६.

तनत् १. ९१, २३.

तर्नयः ३. १, २३; ७. १, १४.

तर्नयं १. ६४, १४; ९२, १३; २. २३, १९; २४, १६; २५, २; ३. १५, २; ६. १३, ६; ४८, १०; ७. ५६, २०; ६०, ८; ९. ७४, ५; १०. ३९, १४.

तर्नयस्य १. १००, ११; ११२, ४; २२; १६६, ८; २. ३०, ५; ४. २४, ३; ६. १९, ७; ४४, १८; ७. ८२, ९.

तनया ८. २५, २.
तनयानि ९. ९१, ६; १०. ४, ७.
तनयाय १. ६२, ३; ९६, ४; ११४, ६; १८३, ३; १८४, ५; १८९, २; २. ३३, १४; ३. ५३, १८; ४. १२, ५; ५. ५३, १३; ६९, ३; ६. १, १२; ५०, ७; ६२, १०; ७. ५२, २; ८. ९, ११; १०. ३५, १२.
तनयित्नुः १०. ६६, ११.
तनयित्नोः ४. ३, १.
तनये १. ३१, १२; ११४, ८; १४७, १; ४. ४१, ६; ६. १८, ६; १९, १२; २५, ४; ३१, १; ७. १, २१; ६७, ६; ८४, ५; ८. २३, १२; ७१, १३; १०३, ७; १०. १४७, ३.
तनयेषु ७. ४६, ३.
तनवावहै १. १७०, ४.
तनसा ५. ७०, ४.
तना १. ३, ४; २६, ६; ३८, १३; ३९, ४; ७७, ४; २. २, १; ३. २५, १; २७, ९; ६. ४९, १३; ७. १०४, १०; ११; ८. २५, २; ४०, ७; ९४, ५; ९. १, ६; १६, ८; ३४, १; ५२, २; ५८, ४; ६२, २; ७१, २; १०. ५०, ६; १४८, १.
तना १०. ९३, १२.
तनाय १. ३९, ७; ८. १८, १८.
तनु १. १२०, ११.
तनुते १. १०१, ७; ११५, ४; १०. १३०, २.
तनुथाः ५. ७९, ९.
तनुध्वं १०. १०१, २; ३.
तनुष्व १. १४२, १; २. ३३, १४; ४. ४, ४; ८. १३, १४; १०. १२०, ४.
तनुहि ४. ४, ५; १०. ११६, ६; १३४, २.
तनू इति १०. १८३, २.
तनूः ४. १०, ६; ६. २४, ७; ७५, १२; ८. ३, २४; १०. ५६, २; ८३, ५; ८५, ३०; १००, १०.
तनूऽकृत् १. ३१, ९.
तनूकृत्ऽभ्यः ८. ७९, ३.
तनूऽकृथे ८. ८६, १.
तनूत्यजः १०. १५४, ३.
तनूत्यजाऽइव १०. ४, ६.
तनूंऽनपात् १. १८८, २; ३. ४, २; १०. ११०, २.
तनूऽनपात् १. १३, २; १४२, २.
तनू३ऽनपात् ३. २९, ११; ९. ५, २.
तनू३ऽनपातं १०. ९२, २.
तनूनां १. ५, १०; ८९, ९; १७९, १; २. ९, २; २१, ६; २३, ८; ३९, ४; ५. ४, ९; ६७, ५; ६. ४८, २; ५१, ६; ७. ३४, १३; १०४, १०; ९. ६६, १८; १०. १५७, ३.
तनूऽपा ७. ६६, ३; ८. ९, ११.
तनूऽपाः ४. १६, २०; ६. ४६, १०; १०. ४६, १; ६९, ४; ८८, ७; ८.
तनूऽपां ८. ७१, १३.
तनूभिः १. ८९, ८; १६५, ११; ४. २, १४; ५१, ९; ५. ७०, ३; ४; ७. ५७, ३; ८६, ५; १०. १२८, ५.
तनूभ्यः १०. १५८, ४.
तनूऽरुचं २. १, ९.
तनूऽरुचा ६. २५, ४; ७. ९३, ५.
तनूऽशुभ्रं ५. ३४, ३.
तनूषु १. ५५, ८; ६८, ४; ८५, ३; ८८, ३; ३. १९, ५; ५३, १८; ५. ५७, ६; ६०, ४; ६. ४६, ४; ७४, ३; ७. ३०, २; ८. २०, ६; १२; २६; ३९, २; ९. ६५, ३०; १०. ५६, ४; ५; ५७, ६; १३२, ५.
तने २. ९, २; ५. ४१, ९; ६. ४६, १२; ८. २६, २; ४६, २५; ६८, १२; ९. ४४, १.
तनोमि १०. १२५, ६.
तनोषि ४. ५२, ७.
तंतयः ६. २४, ४.
तंतवः ९. ८३, २; १०. १३४, ५.
तंतुः २. २८, ५; ९. ७३, ९; १०. ५७, २.
तंतुऽभिः १०. १३०, १.
तंतुं १. १४२, १; १५९, ४; २. ३, ६; ४. १३, ४; ६. ९, २; ३; ८. १३, १४; ९. २२, ६; ७; ६९, ६; ८६, ३२; १०. ५, ३; ५३, ६; ५६, ६; १७२, ३.
तंतून् १. १६४, ५.
तंत्रं १०. ७१, ९.
तंदते १. १३८, १.
तंद्रत् २. ३०, ७.
तंद्रयुः ८. ९२, ३०.
तन्यता १. ८०, १२.
तन्यति ६. ३८, २.
तन्यतुः १. २३, ११; ३२, १३; ११६, १२; ५. २५, ८; ६. ६, २; ७. ३, ६; ९. १००, ३; १०. ६५, १३.
तन्यतुं १. ५२, ६; ९. ६१, १६.
तन्यतोः १०. ६६, १०.
तन्यतोःऽइव ४. ३८, ८.
तन्यवः ५. ६३, २; ५.
तन्वः १. ३१, १२; ७२, ३; ५; ११४, ७; १४०, ६; ११; १६२, २०; १६५, ५; २. १७, ७; ३६, ५; ३९, ६; ३. २०, २; ५०, १; ४. १६, १७; २४, ३; ५. १५, ३; ४१, १७; ६०, ४; ८०, ५; ६. ४६, १२; ७. ५६, ११; ५९, ७; ९१, ४; ८. ४४, १५; ४८, ९; १०. ४, ७; ७, ७; ८, ३; १६, ४; २८, ११; १२; ५१, १; २; ४; ५४, ३; ५६, १; ७२, ८; ९५, ५; ९; ९७, १०; ९८, १०; १००, १०; १०७, ६; १०८, ६.
तन्वते ६. ५९, ७.
तन्वते १. १३४, ४; १५९, ४; ५. १३, ४; १५, ३; ४७, ६; ९. १०, ५; ६६, ५; १०. ७१, ९; १०१, ४.
तन्वन् १०. ५३, ६.
तन्वंतः ४. ४५, २.
तन्वंति १. १९, ८.
तन्वंति ९. ९९, १.
तन्वं १. १२३, ११; १४७, २; ४; २. १७, २; ३. १, १; १८, ४; ४८, ४; ५१, ११; ५३, ८; ४. १६, १४; ५. ८०, ४; ६. ११, २; ५१, ७; ६६, ४; ७. ८, ५; ९५,

३; १०१, ३; १०४, १७; ८. ११, १०; ४४, १२; ७६, १२; ९१, ६; ९६, १५; ९. ७०, ८; ७३, २; ९६, २०; १०. ७, ६; १०, ३; ७; ११; १२; १३, ४; १५, १४; ५६, २; ५९, ५; ७; ७१, ४; ८१, ५; ८५, २७; १०४, ९; ११२, ३; ११६, ६; १२०, ९; १२८, १; १५७, २; १६९, ३.

तन्वा १. १२३, १०; १२४, ६; १८१, ४; २. १०, ५; ३५, १३; ३९, २; ३. ४, ६; १५, २; ३४, १; ४१, ६; ४. ३८, ७; ५६, ६; ६. ९, ४; ४९, १३; ७५, १; ७. ३, ९; १९, २; ११; ७२, १; ८६, २; ९९, १; १०४, १०; ११; ८. १, १८; १००, १; १०. १०, ११; १२; १४, ८; १६, ५; २७, २; ३४, ६; ५४, २; ६५, २; १२८, ३.

तन्वाथे इति १०. १०६, १.

तन्वानः ३. ३, ६; ९. ८६, ३२.

तन्वानं ९. २२, ६.

तन्वाना ९. १०२, ७.

तन्वानाः ७. १०, २; ८. ४३, २०; ५९, ६; १०. ९०, १५.

तन्वि १. ५५, ८; २. १६, २; ४. ६, ६; ६. ४९, १२; ८. ९६, ११; १०. ६५, ७; ६६, ९.

तन्वे १. २३, २१; ८४, १७; १६५, ११; १५; १६६, १५; १६७, ११; १६८, १०; १८९, ६; २. ३९, ५; ४. १८, १०; ५. ४, ६; ६. १८, १४; ४०, ४; ४१, ५; ४६, १२; ८. १७, ६; ४६, १५; ६८, १२; ९६, १०; १०. ८, ४.

तप ३. १८, २; ६. ५, ४; २२, ८.

तप २. २३, १४.

तपः ७. ८२, ७; १०. १०९, १; १५४, २; १६७, १.

तपःऽजान् १०. १५४, ५.

तपःऽभिः ७. १, ७.

तपत् १. १६२, २०.

तपत ८. ८९, ७.

तपंतं ७. १०४, १.

तपति २. २४, ९; ३. ५३, २२; १०. ६०, ११.

तपतु ८. १८, ९; १०. १६, ४; १८२, ३.

तपनः २. २३, ४.

तपनाः १०. ३४, ७.

तपनी २. २३, १४.

तपंतः ५. ४३, ७.

तपंतं ९. १०७, २०.

तपंति ६. ५९, ८; ७. ३४, १९.

तपंति १. १०५, ८; ३. ५३, १४; ७. ८३, ५; १०. २७, २२.

तपसः १०. १२९, ३; १८३, १[२]; १९०, १.

तपसा ६. ५, ४; ८. ५९, ६; ६०, १६; ९. ११३, २; १०. १६, ४; ८३, २; ३; ८७, १४; १५४, २[२]; १६९, २.

तपसे १०. १०९, ४.

तपस्व १०. १६, ४.

तपस्वतः १०. १५४, ४; ५.

तपस्वान् ६. ५, ४.

तपाति ५. ७९, ९.

तपिष्ठ ६. ५, ४.

तपिष्ठाः १०. ८७, २०.

तपिष्ठं ३. ३०, १६.

तपिष्ठेन ४. ५, ४; ७. ५९, ८; १०. ८९, १२.

तपिष्ठैः ४. ४, १; ७. १५, १३.

तपुः २. ४, ६; ६. ६२, ८; ७. १०४, २.

तपुःऽअग्राभिः १०. ८७, २३.

तपुःऽजंभ १. ३६, १६.

तपुःऽजंभः १. ५८, ५.

तपुःऽजंभस्य ८. २३, ४.

तपुःऽपा ३. ३५, ३.

तपुःऽमूर्धा ७. ३, १; १०. १८२, ३.

तपुःऽवधेभिः ७. १०४, ५.

तपुषः ३. ३९, ३.

तपुषा २. ३०, ४; ३४, ९; ८. २३, १४.

तपुषिं १. ४२, ४; ३. ३०, १७; ६. ५२, ३.

तपूंषि ४. ४, २; ६. ५२, २.

तपो इति ३. १८, २[२].

तपोः ९. ८३, २.

तप्तः ५. ३०, १५.

तप्तं १. ११२, ७; ११८, ७; ४. १, ६; १०. ३९, ९.

तप्ताः ७. १०३, ९.

तप्यतुः २. २४, ९.

तप्यते १. १६४, १३; १०. ३४, १०; ९५, १७.

तं १. ४, ९; १०, ६[२]; १८, ५; २३, २३; ३०, १०; ३१, ७; १३; ३३, ११; ३६, ७; ११[२]; ३९, ८; ४०, ६; ४५, १०; ४७, १; ५२, ३; ४; ५३, २; ५५, ३; ५६, २; ५७, ६; ५९, २; ६०, ३; ५; ६६, ५; ७३, ४; ७४, ५; ७७, २; ३; ७८, २–४; ८०, ७; ८१, १; ८२, ४; ८३, १; ८९, ५; ९१, १४; ९२, ८; ९६, ३; १००, ७[२]; ८[२]; १३[२]; १०२, १; ३; १०४, १; १०५, ७; १५; १६; ११३, ३; ११६, ३; १६; ११७, ४; १५; १२१, १०; १२३, ५; १२५, १; १२७, ५; १२८, २; १२९, १; २; १३१, २; ४; ७; १३२, ६; १३६, ४; ५[२]; १४०, ८; १४१, १०; १४३, ६; १४४, ५; १४५, १; २; ३[२]; १५१, ७; १५६, ३; ४[२]; १६२, १५; १६४, ४९; १६६, ८; १६७, ७; १६९, ४; १७३, ५; १८०, १०; १८३, १; १८६, ७; १८७, ११; १९०, २; २. २, ३–५; ६, ३; ९, ३; १३, ५; १४, ४; ११; २०, ४[२]; २३, ४–७; २४, ४; ६; ७; २६, ४; २७, १३; ३०, २; ९; ११; ३४, ७; ९; ३५, ३; ४; १३; ३७, २; ३८, ९; ४०, ३; ३. २, १३; १४; ८, ४; ९, ६; १०, ९; १३, २[२]; ३; २६, २; ९; २७, ४; ६; १४; २८, २; २९, १०; ३०, १९; ३१, ४; १९; ४२, २; ४६, ५[२]; ४७, ५; ४८, २; ५३, २१; ५८, ९; ४. १, ९; २, ८; ४, ४; ५,

७; ७, ५; ६; १०, १; १३, ३; १५, ६; १०; १६, ९; १६; २१, ४; २४, ३; ६; २५, ५; ३२, १३; ३६, ७; ९; ३७, ८; ३९, १; ३; ४६, ६; ५०, १; ९; ५८, ११; **५.** २, ६; ६, १; ९, ७; १४, २; ३; १६, ४; १७, २; १८, ३; २०, १; २२, ४; २३, २; २४, ४; २६, २; २९, १२; ३०, १५; ३२, ६; ११; ३३, ३; ३५, १; ५; ४०, ९; ४२, १०; ११; ४४, १; ८; १४^{३}; ५२, १३; ५३, १०; ५४, १२; ५६, ७; ९; ५८, १; ६३, ४; ८२, ३; **६.** १, २; ६; ३, २; ५, ४; ७; १०, २; ३; १५, १०; ११^{३}; १६, ११; १४; ३२; १९, ४; ७; २०, १; २१, ६; २२, १; २; ३^{२}; ५; ७; २३, ९; २४, ६; १०; ३३, १; ३५, ५; ३६, ३; ३८, ३; ४०, २; ४४, ५; १४; ४५, १०; ४६, ३; ४८, १४; ५२, १; २; ८; ५४, ४; ६०, १०; ६६, ११; ७५, १९; **७.** १, २; ३, ५^{२}; ४, ५; ५, ९; ६, ४; १६, ४; १२; २०, ५; २५, २; २६, ४; ३१, ८; ३२, १२–१४; ४१, ५; ४७, १; २^{२}; ५९, ८; ६८, ९; ८२, ७; ९०, २; ९७, ३–६; ९८, ४; १००, ५; १०४, १६; **८.** २, ३; ३, ८; ६, ९; १६; १७; २७; १२, १–३; १३, ३; १७; १८; २४; १५, १; ४; १६, ३; ५; ६^{२}; ९^{३}; १८, १४; १९, १; ६; ३२; २१, ९; २३, ७^{२}; १६; २०; २४, १८; २६; २७, १५; ३१, २; १७; ३२, १३; ३९, ८; ४०, १०; ११; ४१, २; ४३, २०; २३; २८; ४६, ६; ७; १२; ४७, ७; १६; ५१, ३; ५; ६; ५३, ८; ५८, ३; ६०, १६; ६१, २^{२}; १४; ६२, १२; ६४, ७; १२; ६८, १०^{२}; ६९, ११; ७०, २; ३; ८; ७१, ४; ७२, ३; ७५, ५; १४; ८१, ८; ८४, ८; ८८, १; ९०, ६; ९३, ७; ९५, ६; ९६, ६; १३; २०; ९७, २; ३; १३; १०२, १७; **९.** १, ७; ८; २, ८; ६, ६; १२, ५; १७, ७; २६, १–६; ३५, १५; ४३, १; २; ४८, १; ५२, ३; ५३, ४; ६०, २; ६१, १४; ६२, १७; १८; ६३, १७; ६४, २३; ६५, ११; २७; ६६, २०; ६७, ३०; ६८, ६; ७१, २; ७४, १; ४; ८०, ४; ५; ८६, ३९; ९५, ४^{२}; ९८, ९; १२; ९९, ३–५; १०१, ३; ९; १०५, १; १०७, १३; १७; १०९, ११; ११३, ३^{२}; ११४, १; **१०.** ६, ५; ७; १२, ६; १६, ४^{२}; १०; १३; १७, १२; १३; १९, ४; २१, ४; २७, ३; ४; ७; ११; १६; ३०, ९; ३७, ५; ६; ३८, ४; ३९, १; ११; ४२, ९; ४५, २; ९; १०; ४६, ८; ५१, ३; ५७, २; ६२, ९; ६७, ९; ८२, ३; ६; ७; ८३, ५; ८७, ६–८; ११; १७; ८८, ५; ८^{३}; १०; ९०, ७; ९१, ६^{३}; ८^{२}; ९७, २२; १०१, ८; १०२, ९; १०; १०७, ५; ६^{२}; १०८, ४; ७; ११०, ९; ११३, १; २; ११४, ४^{२}; ७; ११८, ५; ६; ९; १२२, ३; १२५, ५^{३}; १२६, १; १३३, २; ४; १३५, ४; १६०, ४; १६१, २; १६२, २; ३; १६३, ५; १६४, ५^{२}; १८४, ३.

तमः **१.** ३२, १०; ३८, ९; ४६, ६; ५४, १०; ५६, ४; ८६, १०; ९१, २२; ९२, ४; ११३, १६; ११७, १७; १२३, ७; **२.** २४, ३; **४.** १, १७; १३, ४; ४५, २; ५२, ६; **५.** १४, ४; ३१, ३; **६.** ८, ३; १०, ४; २१, ३; ४८, ६; ६४, ३; ६५, २; **७.** ९, २; ७५, १; ७८, ३; ७९, २; ८०, २; ८१, १; **९.** १०८, १२; **१०.** ३७, ४; ६८, ५; ११; ८८, १२; ११३, ७; १२४, १; १२७, २; ३; ७; १२९, ३; १५२, ४; १७२, ४.

तमःऽगां **५.** ३२, ४.

तमःऽभिः **८.** ६, १७.

तमःऽवृधः **७.** १०४, १.

तमःऽहने **१.** १४०, १.

तमःऽहना **३.** ३९, ३.

तमत् **२.** ३०, ७.

तमसः **१.** ३३, १०; ५०, १०; ९२, ६; १२१, १०; १७३, ५; १८३, ६; १८४, ६; **३.** ५, १; ३१, ४; ३९, ७; **४.** ५१, १–३; **५.** १, २; **६.** ५०, १०; ६५, १; **७.** ६७, २; ७१, ५; **१०.** १, १; १०७, १.

तमसा **१.** १२३, ६; **२.** २३, १८; **४.** ६, ६; **५.** ४०, ५; ६; **१०.** ८८, २; ८९, १५; ११३, ६; १२९, ३; १६२, ६.

तमसि **१.** १००, ८; ११७, ५; १८२, ६; **३.** ३९, ५; **५.** ३२, ५; ६; **६.** ९, ७; **७.** ६, ४; १०४, ३; **१०.** ५१, ५; ६७, ४.

तमसे **४.** १३, ३.

तमांसि **२.** १७, ४; २३, ३; ४०, २; **३.** २७, १३; **४.** १६, ४; ५०, ४; **५.** ३१, ९; ८०, ५; **६.** ४, ६; ९, १; ७२, १; **७.** ५६, २०; ६३, १; ७७, १; ७८, २; **८.** ४३, ३२; ७४, ५; **९.** ९, ७; ६६, २४; १००, ८; **१०.** १, २; ६८, ९; ७३, ५; ८९, २.

तमिषीचीः **८.** ४८, ११.

तमिस्राः **२.** २७, १४.

तंऽते **१.** १३२, ६^{२}; **८.** ६८, ७; **१०.** १२५, ५.

तम्राः **१०.** ७३, ५.

तया **१.** २२, ३; ८५, ११; **३.** ५७, ५; **६.** ४१, २; ४५, १४; ५३, ८; **८.** ७४, ८; **९.** ४५, ६; ४९, २; **१०.** ८७, १३.

तयोः **१.** १७, ६; २१, १; २२, १४; १३६, ३; १६४, २०; **३.** ५५, ११; १५; **५.** ८६, ३; **७.** १०४, १२; **१०.** ११४, १.

तर **८.** ७५, १५; **९.** ५९, ३.

तरः **१.** ३३, १२; १९०, ७; **७.** ९१, ४; **८.** ६७, १९.

तरःऽभिः २. ३९, ३; ८. ६६, १.
तरण्यः ४. ४, १२; ७. ६७, ८.
तरणि ३. ११, ३.
तरणिः १. ५०, ४; ११२, ४; १२१, ६; १२८, ६; ३. ४९, ३; ४. ४५, ५; ७. २६, ४; ३२, ९; २०; ६३, ४; १०. ८८, १६.
तरणिऽत्वा १. ११०, ६.
तरणिऽत्वेन १. ११०, ४.
तरणिऽभिः ४. ३३, १; ८. ६०, ८.
तरणिं ३. २९, १३; ४. ४५, ७; ८. ४५, २८.
तरणे ६. १, ५.
तरत् ९. ५८, १; १०७, १५.
तरत १०. ४२, १; ५३, ८.
तरति ३. ४९, २; ७. १, ५; ९. ९६, १५.
तरति ६. २, ४; ७. ५९, २; ९. १११, १; १०. ६१, १६.
तरते १०. १०६, ९.
तरत्ऽद्वेषाः १. १००, ३.
तरध्यै ९. ११०, १.
तरन् ३. २४, १.
तरंतः २. ११, १९; ६. १६, २७; ८. ४३, ३०; ६०, १२; १०. ३१, १.
तरंतःऽइव ५. ६१, १०.
तरंतं १. १०५, ११.
तरंति ७. ३२, १३; ९. ७३, ६; १०. २७, २१.
तरंती इति ४. ५६, ७.
तरसंती १०. ९५, ८.
तरसा ५. ५४, १५.
तरसि ६. ६४, ४.
तरसे ३. १८, ३.
तरस्विनः ८. ९७, १२.
तरस्विनं ८. ९७, १०.
तरामसि ७. ३२, २७.
तराय २. १३, १२; ८. ९६, १.
तरित्रतः ४. ४०, ३.
तरीयान् ५. ४१, १२.
तरीषणि ४. ३७, ७; ५. १०, ६.
तरुक्षे ८. ४६, ३२.
तरुणः ७. ४, २.
तरुणं १. १८६, ७.
तरुणस्य १०. ११५, १.
तरुणाय ८. १९, २२.
तरुणीः ८. ४३, ७.
तरुणीषु ३. ५५, ५.
तरुता १. २७, ९; १२९, २.
तरुता १. ४०, ८; ८. ४६, ९; ७०, १.
तरुतारं १. ११९, १०; ८. १, २१; १०. १७८, १.
तरुते १०. ७६, २.
तरुत्र २. ११, १५; १६; ७. २१, ९.
तरुत्रः १. १७४, १; ३. ३०, ३; ४. २१, २; ६. १, ११; १७, २.
तरुत्रं १. ११७, ९; ६. २६, २; ७२, ५; १०. ४७, ४.
तरुत्राः ७. २५, ५; ८. १६, ४.
तरुऽभिः ५. ४४, ५.
तरुषः १. १२२, १३; ३. २, ३; ६. १५, ३.
तरुषंत १. १३२, ५.
तरुषंते ५. ५९, १.
तरुषसा १. १२९, १०.
तरुषि ६. २५, ४.
तरुषेम ७. ४८, २.
तरुष्यतः ८. ९९, ५.
तरेत् ६. ६८, ५.
तरेते इति १. १४०, ३.
तरेम ५. ५४, १५; ७. ५६, २४; ८. ४२, ३.
तरेम ३. २७, ३; ६. २, ११^{३}; ६८, ८; ७. ३२, १५; ६५, ३; १०. ४२, १०; ५३, ८; ११३, १०.
तर्तरीति ६. ४७, १७.
तर्तरीथः १०. १०६, ७.
तर्तुराणाः ९. ९५, ३.
तर्तूर्यंते ८. १, ४.
तर्दः ६. १७, १.
तर्पय १. ५४, ९.
तर्पयंत १. ८५, ११.
तर्पयंतं १. १६४, ५२.
तर्पयेथां १. १७, ३; ७. ६४, ४.
तर्यः ५. ४४, १२.
तर्प्यीऽवान् १०. २८, १०.
तर्हणं ७. १०४, ४.
तर्हि १०. १२९, २.
तल्पऽशीवरीः ७. ५५, ८.
तळितः २. २३, ९.
तळित्ऽइव १. ९४, ७.
तव १. १, ६; २, ३; ११, ६; १५, ५; १९, २; २४, ५; १५; २९, २; ३१, १; १०; १२; ५१, ७; १५; ५२, ७; ५३, ३; १०; ५७, ५; ६२, १२; ६३, ६; ८०, ११; १३; १४; ८१, ६; ८३, १; ९१, १; ३; १४; ९४, १–१२; १३^{२}; १४; ९८, ३; १०२, ५; १०५, १३; ११४, २; ३; १३५, २; ३; १५०, १; १६३, ८; ११^{२}; १६९, १; १७०, २; १८७, ४; ५^{२}; ६; २. १, २^{४}; ५; १२; १३, ११; २२, ४; २३, ६; १८; २४, १; २८, २; ३; ३६, ४; ३. १, १६; २, ६; ३, १०; ६, ५; ९, ६; ७; १७, ३; २०, ३; २८, ४; ३०, ४; ३२, ९; ३५, ६; ३६, ३; ४०, ४; ५; ४३, १; ५१, ७^{२}; ४. ३, १४; ४, २; १२; १४; ५, ११; ६, ९; १०, ५; १२, १; १७, २; २८, १; ५. ३, ३; ४; ६, ७; ९, ६; २५, ८; २८, ३; ४, ३८, ४; ५; ४०, ७; ४२, ८; ४४, १४; ६. २, ११; ५, ४; ७; ७, ४; ५; ८, ६; ७; ११, २; १६, ८; ४३; १७, ६^{२}; १९, ८; २०, १३; २१, ७; २६, ७; २८, ८; ३६, १; ४५, २६; ४८, ४; ५०, ९; ५४, ९; ७. ५, ४; १९, ५; ७; २८, ३; ३२, १५–१७; ५५, ४; ६०, १; ८१, २; ८९, ५; ९५, ५; ९८, ६; ८. २, १७; ४, ७; ६, २२; १३, २८; १५, ७^{२}; ८; १७, ६; १९, २८; २९^{३}; ३०; ३१; ३३; २३, ११; २४, ११; २६, २१; ३२, २०; ३३, १६; ४३, ३; ९; १०; ४४, १७^{२}; १८; ४५, ३३; ४८, ८; ६१, ४; १३; ६२, ३; १०^{२}; ६६, १४; ७१, ५; ७७, ७; ७८, १०; ७९, ४; ९२, ३२; ९३, ५;

९९, २; ९. २, ८; ४, ५^{2}; ९, ५; १८, ३; ५१, ३; ५२, २; ५५, २; ६१, १८; २४; २९; ६६, ५; ६; ८२, ५; ८६, १३; २८; २९^{2}; ३७; ८७, ९; ९२, ४; ९७, ४३; १०६, ८; १०७, १९; १०. ७, १; १०, १४; १८, ८; २३, ७; २५, ५; ४४, ५; ५१, ९^{2}; ५७, ६; ६०, ७; ७२, ५; ८३, ५; ९१, ४; ५; ९५, २; ९६, ५; ९७, ४; ८; २३; १०४, ४; ५; ११२, १; १२२, २; १३१, १; १३८, १; १४०, १; १५६, २; १६७, ३.

तवःऽतमः २. ३३, ३.

तवःऽतमा १. १०९, ५.

तवःऽतरं १. ३०, ७.

तवसः १.१३८, १; ३. ३२, ९; ५. ६०, ४; ६. १८, ४; २०, ३; ७. ६, १; १००, ३; १०. २५, ५; २८, ५; ८३, ३.

तवसः १. १६६, ८.

तवसं १. ६४, १२; ३. १, १; १३; ५. ५८, २; ८३, १; ६. १७, ४; ८; ५८, ४; ७. २४, ३; १००, ५; ८. ९७, १०; १०. २८, ६.

तवसा ३. ३०, ८; ७. ९९, ६.

तवसा २. ३३, ३.

तवसे १. ५१, १५; ५७, १; ६१, १; ११४, १; ३. १, २; ५. ३३, १^{2}; ८७, १; ६. ३२, १; ४९, १२; ७. ५, १; ८. ९६, १०.

तवस्यं २. २०, ८.

तवस्वान् ९. ९७, ४६.

तवागां ४. १८, १०.

तविषः १. १६५, ६; ८; ५. ८७, ५; ८. ९६, १८.

तविषं ८. १५, १; ४६, १२; ५७, १; १०. ८८, १३.

तविषस्य ३. ३४, २; १०. ८३, ५.

तविषा ६. ६१, १.

तविषाः ५. ५४, २.

तविषाणि १. १६६, १; ९; ३. १२, ८.

तविषात् १. १७१, ४.

तविषासः १०. ४४, ३.

तविषी १. ३९, २; ४; ५१, ७; ५६, ४.

तविषीः १. ६४, ७; ३. ३१, १३; ४. २१, १; ६. ४१, ४; ८. ६६, १०; १०. १०२, ८; ११३, ५.

तविषीभिः १. ५१, २; ६४, ५; १०; ८७, ४; १६६, ४; २. ३४, १; ३. ३, ५; २६, ४; ४. १९, ४; ५. ३२, ३; ७. २०, ४; ८. ८८, २.

तविषीभ्यः १०. ११३, ६.

तविषीं १. ३५, ४; ८०, १०; १८७, १; ३. ३२, ३; ४. १६, १४; ५. ३१, १०; ३२, २; ९; ३४, ७; ५५, २; १०. २३, ५; ११२, ५; १४२, ३.

तविषीऽमंतं ५. ५८, १.

तविषीऽयंतः ५. ८५, ४.

तविषीऽयमाणं २. ३०, ८.

तविषीऽयवः ८. २३, ११.

तविषीऽयवः ८. ७, २.

तविषीऽयसे ८. ६, २६.

तविषीऽवः ४. २०, ७; ७. २५, ४.

तविषीऽवान् १०. १०५, ३.

तविषीषु १. ५२, २; १२८, ५.

तविषेण १०. १११, २.

तविषेभिः ६. ६१, २.

तविष्यते १०. ११, ६.

तविष्यते ९. ८६, ४५.

तविष्यमाणः ९. ७६, ३.

तविष्यया ९. ७०, ७.

तविष्याः ५. २९, १४.

तवीति १०. ५९, १.

तवीयः ६. १८, ४.

तवीयसः १०. ९२, ८.

तवीयान् ६. २०, ३; ७. १००, ३; १०. ८३, ३.

तव्यं १. ५४, ११.

तव्यसः ५. ४३, ९.

तव्यसीं १. १४३, १.

तव्यसे १. ४३, १.

तव्यांसं ५. १७, १.

तव्यान् ३. ३२, ११; ५. ३२, ३; १०. ११७, ५.

तष्टः १. १७१, २.

तष्टं ६. १६, ४७.

तष्टाऽइव १. ६१, ४; १०५, १८; १३०, ४; ३. ३८, १; ७. ३२, २०; १०. ९३, १२; ११९, ५.

तष्टान् १. ६७, २.

तष्टानि १०. ८६, ५.

तष्टेषु १०. ७१, ८.

तसराणि १०. १३०, २.

तस्करः ६. २८, ३; ८. २९, ६.

तस्करं ७. ५५, ३.

तस्करा १०. ४, ६.

तस्कराःऽइव १. १९१, ५.

तस्तभानान् ८. ९६, १८.

तस्तभाने इति १०. १२१, ६.

तस्तभुः ८. ९४, ११.

तस्तभुः ८. ५५, २.

तस्तभ्वांसं २. ११, ५.

तस्तंभ १. ६७, ३; १६४, ६; ४. ५०, १; ७. ८६, १; ९. १०१, १५; १०. ८९, ४.

तस्तंभत् १. १२१, ३.

तस्थतुः १. १५५, १; ९. ६६, २.

तस्थतुः १. ११३, ३; ३. ६, १०; १४, ३; ५४, ७; ४. ५६, २.

तस्थथुः ८. २२, १.

तस्थथुः १०. ८५, १५.

तस्थिम ९. ११२, ३; १०. १३६, ३.

तस्थिरे ८. ७, ८; ९. ६२, २७.

तस्थिऽवांसः १. ३३, १५; ३. ८, ६; ५६, १; ४. ४, ९.

तस्थिऽवांसं १. ७२, ४; २. ३५, १४; ६. ९, ७; ७. ८९, ४; १०. ४५, ३.

तस्थिऽवांसा १. १०८, १.

तस्थिऽवान् ५. ८५, ५.

तस्थुः १. ७२, २; ९; १०५, १०; १६४, २; ३; १६९, ६; ३. ५४, ९; ५. ४७, ५; ६०, २; ७. ६, ६; १०१, ४; १०. १३, १; ८२, ६; १०४, ४.

तस्थुः १. ३५, ५; ६; ५२, ४; ८५, ६; ९५, ६; ११२, २; १४०, ८; १६४, ११; १३; २. १५, ५; २४, ७; ३५, ३; ३८, ७; ३. ३०, ४; ५६, २; ४. ५४, ५; ५. ६२, १; ६९, २; ६. ८, ४; ७. ९१, ३; ८. ९६, १.

तस्थुर्वः १. ६, १; ८९, ५; ११५, १; ३. ३८, ९; ५. ५२, २; ७. ३२, २२; ६६, १५; १०१, ६.

तस्थुर्षीः ५. ६२, २.

तस्थे १. ७२, ९; ५. ४४, ९; ६. २१, ७; १०. ४८, ५; १०९, ३.

तस्थौ १. ६४, १३; ५. ५६, ८; ६. २०, १; ७. ८, ४; ८. १०२, १४; १०३, २; ९. ८४, २; १०. २७, १४; १०५, ५.

तस्थौ १. ३३, १४; ६४, ९; १४६, २; १६४, १०; ३. ७, २; ३८, ४; ५५, १४; ४. ५०, ७; ६. ६३, ५; ६६, ६; ८. ५२, ७; १०१, १४; १०. ४, ५; ५, ६; २०, ५; २८, २; ४८, १०; ७३, १०; ८८, १६; १३९, ३.

तस्मात् १. १६४, ३२; २. २८, १०; ६. १६, ३१; ७. ८९, ५; ८. १०१, ४; १०. ५१, ६; ९०, ५; ८; ९^{२}; १०^{३}; १२९, २.

तस्मिन् १. ८०, १५; १६; १४५, १^{२}; १६४, १३; १४; ४८; १७६, २; ३. ३, ३; ४. २, ७; २४, ७; ४१, ४; ५. ३४, ९; ७. १८, १८; ६०, ८; १०१, ६; ८. ४६, ७; ९७, २; ९. ११३, ७; १०. १६, ८; ३७, १२; ८८, ७.

तस्मै १. ४, १०; १२, ९; ४०, ४; ६८, ३; ९३, २; १०; ११६, १६; १२५, ५^{२}; १३२, ५; १६१, १२; २. १४, २; ३; ५; २०, ८; २५, ४; ५; ३७, १; ३. ५९, ५; ४. १६, १; २५, ४; ३५, ६; ५०, ८^{२}; ५. ३४, ९; ३७, १; ३९, ५; ६३, १; ६. २३, ९; ५२, २; ७. १९, ९; २६, १; ५९, १; १०२, ३; ८. ८, १५; ४४, १५; ४८, १०; १२; १३; ६६, ७; ७५, ६; ८०, १०; ९. ६७, ३२; १०. ९, ३; २८, १०; ३०, ३; ७;, ३४, १२; ४२, ५; ७९, ५; १३५, २; १६५, १; ४; १६८, ४; १७३, ३^{२}.

तस्यं १. ११, ६; १२, ८; २२, ६; ३६, ११; ४२, ४; ५६, १; ५९, ३; ८३, ६; ९३, ८; १००, १३; १०४, ९; १४१, ७; १४८, २; १६४, १; १३; २२; २. २३, १२; २४, ८; २५, २; ३२, २; ३५, ९; ३. १, २१; ३, ९; १७, ५; ३३, ६; ३५, ८; ३९, १; ४. २, ६; ४, १०^{२}; २१, २; ४१, ११; ४२, ७; ५. १२, ६; ३९, २; ४८, ५; ५५, ८; ८७, ९; ६. ७, ६; २८, ४; ३९, १; ४९, १३; ५०, १५; ७. ३१, ११; ४०, ३; ७२, २; ८. ४, १२; १७; ७, १८; १९, ६^{२}; २३, १५; २५, १६; ३१, ३; ३८, १; ४१, ३; ४५, १५; ४८, ८; ६४, १०; ९. ६५, ९; १०. ९, २; १०, १४; १५, ७; २२, ८; २७, २४; ४०, ११; ४३, ३; ५१, ४; ७१, ६; ८५, ३; २१; ८७, १०^{२}; १७; ८८, १; २; ९१, ११; ९९, १; ११७, ६; १३३, ५; १३९, १; १४९, २; १६०, ३.

तस्याः १. ७१, १०; १६४, ४२; २. ७, २; १३, १; ५. २९, १४; ६. ५३, ९; ७. ८१, ४; १०. ३९, ६; १६१, १.

तस्यां ७. ५७, ४; १०. ११४, ३.

तस्यै २. ३२, ७.

ता १. १३, ८; १५, ८; १७, १; ३; २१, १; २^{२}; ३^{२}; ५; २२, २; २३, ५; २८, ७; ८; ३२, १५; ५१, ८; १३; ९१, १९; १०९, ३; ११८, १०; १२०, ३; ७; १२; १३६, १; १५४, ६; १६१, ७; १६२, ८; ९; १४; १७^{२}; १६४, १६; ३८; १६५, ४; १७३, ४; १७४, ८; १८४, १; २. १३, २–४; १५, २–९; २४, ५; ११; ३३, १३; ३४, ४; ४१, ६; ९; ३. ३, १०; १२, ३; ३१, ५; ५५, ६; १०; ५६, १; ४. १, ७; २, २०; १६, १६; २२, ५; ३०, २२; ३२, ११; ४१, ३; १०; ४२, ६; ७; ५. २९, १३; ६४, २; ६५, २^{२}; ३; ६६, २; ३; ६८, ३; ७०, २; ७३, ९; ८५, ८; ८६, २; ५; ६; ६. २, ११; ४, ८; १३, ५; १६, २४; १७, १३; २१, ४; ७; २९, ५; ३७, ५; ६०, २; ४; १२; १४; ६१, १; ६२, २–४; ५; ६; ६७, ६–८; ६८, २^{२}; ३; ७. २, ७; २६, ३; ३४, २२; ६४, ४; ६५, २^{२}; ३; ६६, ३; ६७, ५; ७४, ५; ८५, १; ९३, १; २; ९४, ५; ६; ८. ५, ६; ३६; ३७; ८, ९; १०, ४; २१, ८; २२, ६; १४; २५, १; ३; २३; २६, ३; ३१, ६; ८; ४०, ३; ४५, २५; ७७, १०; ८६, १; ८७, २–४; ९१, ६; १०१, २; १०२, २०; ९. ८६, ३८; १०. १०, १०; १४, १६; २२, ११; १३; २४, ६; ३९, ४; ५; १३; ५९, २; ६६, ७; ७३, २; ८६, २०; ९६, ६; १०६, ६; १३२, २.

ताः १. ९, ८; २३, १७; ८४, ११; १२; ११३, १८; १२४, ९; १५१, ५; १५५, ३; १८८, ८; १९१, १२; १४; २. ५, ५; २३, ३; ३. ७, ३; ४. २२, ७; ४१, ८; ४७, ४; ५१, ७^{२}; ८; ९; ५८, ८; ५. २, ४; १९, ५; ३०, १०; ४६, ७; ४८, २; ६. २८, ३; ४^{३}; ६५, २; ७. २७, १; ४७, ३; ४९, १; ५०, ४; ५५, ८; ८. ४३, १८; ४५, ३३; ६९, ३; ९. ९, ५; ७४, ६; ७८, ३; ८६, २७; ३७; ८७, ९; ८९, ५^{२}; १०. १, ४; ९, १; २७, ८; ३०, ५; ६१, ८; ९५, ६; ८; ९; ९७, १४; १५; ९८, ६; १०३, ११; १२४, ७; ८^{३}; १३२, ७; १३७, ६.

तात् ६. २१, ६; १०. ९५, १६.

ताऽर्ता १. १६२, १९.

तात्या १. १६१, १२; ७. ३७, ६.

तादीत्नां १. ३२, ४.

तादृक् ५. ४४, ६.

तान् १. १२, ४; १४, ७; १६, ६; २३, १; ४५, २; ७४, ६; ८९, ३; ९४, ३; १०४, २; १४७, ३; १६४, १६; १९^{२}; १७७, २; १८९, ७; २. १, १५; १६; २, १३; २७, १६; ३४, ११; १४; ३. २१, ५; ४२, ५; ४५, १; ५४, २२; ४. ५, ४; ३१, १३; ३६, २; ७; ५. ५१, ६; ५६, २; ६. २२, ८; ३३, ३; ५१, ९; ७. ६, ३; १६, ८; १०; ३२, ४; ३३, ७; ३९, ४; ५८, ५; ८५, २; ९८, ४; १०४, ९; ८. २, ११; २०, १४^{२}; ५७, ३; ७५, १५; ७७, ३; ९३, ६; १४; ९६, ९; ९. ७९, ३; ९१, ५; ९७, २०; ९८, ११; १०७, १९; १०. २२, १०; ३८, ३; ६३, ३; ५; ८५, ३१; ८९, १५; ९०, ८; ११५, ९; १२८, ९; १३०, ६; १५४, १.

तानि १. ५३, ६; ८५, १२; १३९, ८; १६१, ३; १६४, १९; ४३; ४५; ५०; १७१, ४; १८२, ४; २. ३८, ७; ३९, ८; ३. ३४, ७; ३७, ९; ५४, १२; ६०, १; ४. ४२, २; ५५, ८; ६. ७, ५; २५, ५; ७. १९, ५; २३, २; ७६, ३; ८. २, ३०; ४२, १; ६३, ८; ९१, ५; ९. ९, ७; २९, ३; ८४, २; ९४, ५; १०. ५४, ४; ८५, ३५; ९०, १६.

तान्वः ३. ३१, २; १०. ९३, १५.

तान्वा ९. १४, ४; ७८, १.

तापयिष्णवः १०. ३४, ७.

ताभिः १. १४, १२; ४७, ५; ५०, ९; ९१, ९; ११२, १–२३; २. ३२, ५; ३. १७, ३; २०, २; ४. ३३, ४; ६. २५, १; २८, ३; ५८, ३; ६०, ८; ९; ७. ३, ८; ८. ५, २४; ८, २०; २१; २२, १०; १२^{२}; ५९, ३; ४; ९. ६२, ७; १०. १६, ४; ८७, ४; १०४, ९; १६८, २; १८८, ३.

ताभ्यः १०. १९, ८; १६९, २.

ताभ्यां ६. ५७, ३; ९. ६६, २; १०. १४, ११; ८८, १५; १३७, ७.

तां १. ४६, ६; ४९, ४; १०८, ६; १३७, ३; १३८, ३; १३९, ७^{२}; १७५, ६; १७६, ६; ३. ५७, ६; ६२, ८; ४. ४२, १०; ४४, २; ५७, ७; ५. ४१, १८; ४६, १; ४८, ४; ६. ५७, ५; ७. ५, ८; ८. १००, ११; १०. २७, ११; ५४, १; ६४, १२; ७१, ३^{३}; ७२, ५; ८५, ३७; १२५, ३; १३३, ७; १५६, २; १७७, २^{२}.

तयते १. ११०, १.

तायमाने १०. १७, ७.

तायवः १. ५०, २; ५. ५२, १२.

तायुः ५. १५, ५; ६. १२, ५.

तायुं १. ६५, १; ४. ३८, ५; ७. ८६, ५.

तारः ८. ५५, २.

तारि १. ११९, ६; ४. १२, ६; ९. ९३, ५; १०. ५९, १; ११४, ५.

तारिषुः ९. ७९, ५.

तारिषत् १. २५, १२; ४. ३९, ६; ८. १९, १४; १०. २५, ११; १८६, १.

तारिषीमहि २. २३, १०.

तारिष्ट १. ३४, ११; १५७, ४.

तारीः ६. ८, ७; २५, २; ८. ४८, ४; ७; १०. ५४, ५.

तारीत् १. ६९, ३; ७३, १; १५२, ३; २. २०, ८; ६. ४७, ९; ८. ७९, ६; ९. ११४, ४; १०. ६९, ५.

तार्क्ष्यः १. ८९, ६.

तार्क्ष्यं १०. १७८, १.

ताळ्हि १०. १८०, २.

तावकेभ्यः १. ९४, ११.

तावत् ६. २३, ६; ७. ७९, ४; १०. ८८, १९; ११४, ८.

तावती १०. ११४, ८.

तावान् १. १०८, २.

तासां १. ३२, ८; ११२, ३; १४०, ८; २. ५, ६; ३. २, ९; ६. १७, १२; १०. ५, ६; ९७, १८; ११४, २; १६९, ४.

तासु २. २८, ९; ३५, १३.

तिगितेन २. ३०, ९.

तिगितैः १. १४३, ५.

तिग्मऽअनीकं १. ९५, २.

तिग्मऽआयुधः २. ३०, ३; ९. ९०, ३.

तिग्मऽआयुधाः ५. २, १०.

तिग्मऽआयुधाय ७. ४६, १.

तिग्मऽआयुधौ ६. ७४, ४.

तिग्मऽइषवः १०. ८४, १.

तिग्मऽजंभ १. ७९, ६.

तिग्मऽजंभः ४. ५, ४.

तिग्मऽजंभस्य ४. १५, ५.

तिग्मऽजंभाय ८. १९, २२; ४४, २७.

तिग्मऽभृष्टिः ४. ५, ३.

तिग्मं १. १३०, ४; ३. ४८, ३; ४. ६, ८; ६. ३, ४; ७. १८, १८; ८. २५, १५; २९, ५; ४७, ७; ७२, २; ९६, ९; १०. ६१, ३; १८०, २.

तिग्मऽमूर्धानः ६. ४६, ११.

तिग्मऽशृंगः ६. १६, ३९; ७. १९, १; ९. ९७, ९; १०. २८, २; ८६, १५.

तिग्मऽशृंगं १०. ४८, १०.

तिग्मऽशोचिषे १. ७९, १०.

तिग्महेती इति तिग्मऽहेती ६. ७४, ४.

तिग्मऽहेते ४. ४, ४.

तिग्मा ४. १६, १७; २३, ७; ५. ८६, ३; १०. १०८, ५.

तिग्माः ५. १९, ५; ८. ४३, ३; ६०, १३.

तिग्मानि ९. ६१, ३०; १०. ११६, ५.

तिग्मां ४. ७, १०.

तिग्मे इति ९. ८७, ७.

तिग्मेन १. ३३, १३; ६. १५, १९; १६, २८; ८. ४३, २६; १०. ८७, २३.

तितउना १०. ७१, २.

तितिक्षते २. १३, ३.

तितिक्षंते ३. ३०, १.

तितिरुः १. ३३, ८; २. २३, ५.

तितिर्वः ६. ४१, ४.

तितिर्वांसः १. ३६, ७.

तितृत्सान् १०. ७४, ४.

तितृप्सात् १०. ८७, १७.

तित्याजं १०. ७१, ६.

तित्रतः २. ३१, २.

तित्विषाणः ८. ९६, १५; १०. ५५, १.

तित्विषाणस्यं ५. ८, ५.

तित्विषे १. ५२, ६.

तित्विषे १. १०२, ७; ८. ६, ५; १२, २४.

तिर १. १०, ११; ११, ७; ४२, १; ९४, १६; ३. १७, २; ८. ३२, ३; ४४, ३०; ५३, ६; ९. १९, ७; १०. ५९, ५; १३३, ५.

तिरः १. १९, ७; ८; ४१, ३; ४६, ६; ५६, ५; ६१, ७; १३५, ६; ३. २७, १३; ४०, ३; ५८, ५; ४. २९, १; ३८, ४; ५. ५३, १४; ७४, ८; ७५, २; ७; ६. १०, ४; ४८, ६; ५१, १०; ६५, १; ७. ९, २; ३३, २; ५०, १; ५९, ८; ६०, ६; १२; ६८, २; ३; ८. १, १५; ३३, १४; ५१, ९; ६६, १२; ७४, ५; ८२, ९; ९४, ७; ९. ३, ७; ८; ६२, १; ८; ६७, ४; ७; ६८, २; ७२, ३; ७३, ३; ७७, २; ७९, २; ९७, ११; ४७; १०७, १०; ११; १०९, १६; १९; १०. १०, १; ८९, १६; ९२, ५; १२६, ६; १७१, ४; १८२, १; १८७, २.

तिरःऽअंन्ह्यं १. ४५, १०; ४७, १; ३. २८, ३; ६; ५८, ७; ८. ३५, १९.

तिरःऽहितं ३. ९, ५.

तिरत ७. ५७, ५; १०. ९५, १०.

तिरतं ७. ९३, ४; ८. ५९, ७.

तिरतें ६. ६८, ७.

तिरते १. १०४, ४; ५. ४८, २; ७. ५९, २; ८. १९, ३०; १०. ८५, १९.

तिरध्वं ७. ५६, १४.

तिरंत ७. ७, ६.

तिरंत ३. ३३, ७.

तिरंति १०. २७, १५; ३४, ६.

तिरंतु १. ८९, २; १०. ६२, ११; ६६, १०.

तिरंतें ७. ६७, ९.

तिरंते १. १२५, ६; ७. १०३, १०; १०. १०७, २.

तिरश्चता ४. १८, २; ९. १४, ६.

तिरश्चा १. ६१, १२; २. १०, ४; १०. ७०, ४.

तिरश्चीनः १०. १२९, ५.

तिरश्च्याः ८. ९५, ४.

तिरसि ४. ६, १.

तिराति ७. ५८, ३.

तिराते ७. ६१, ४.

तिरामसि ३. ३७, १०.

तिरामि १०. ४९, ९.

तिरिंदिरे ८. ६, ४६.

तिरेत ७. ५८, ३.

तिरेतन ८. १८, २२.

तिरेतं ७. ८४, ३.

तिल्विलायध्वं ७. ७८, ५.

तिल्विले ५. ६२, ७.

तिष्ठ १. ३६, १३; १२१, १२; ३. ३५, १; ५३, २; ४. ६, १; ५. १, ११; ३३, ३; १०. ९५, १.

तिष्ठ १. ३०, ६; ४०, १; ४२, ४; ८४, ३; १०२, ५; १७७, २; ३; ३. ४४, १; ४. ४, ४; ५. २८, ३; ५६, ५; ६. १८, ९; २१, ७; ३१, ५; ७. ३८, २; ८. २३, ५; ६०, १६; ६९, १६; ९. ९६, १२; १०. १६, ३; २९, ८; ६९, १२; १०३, ५; १७३, १; २; १७४, २.

तिष्ठत् १. १७४, ४; ५. ७३, ५; ६. २०, ९; ८. २०, ४; १०. १३२, ७.

तिष्ठत् १. ११८, ५; ४. १, १७; ८. ६९, १५.

तिष्ठत १. १९१, ६.

तिष्ठत १. १५, ९; १०. ५३, ८; १७९, १.

तिष्ठतं १. १८३, ३.

तिष्ठति १. ५१, ११; ५८, २; १२५, ५; ८. २४, ३०; ९. १६, ६; ५४, ३; ६२, १९; ९६, २; ७; १०. २३, ३.

तिष्ठतु १. १३४, १; १०. १८, १२; १९, ३.

तिष्ठते १. ५८, ४; ९२, ५; २. ३८, ५.

तिष्ठथः १. १८३, २; ८. ९, १२.

तिष्ठथः ५. ६३, १; ३; १०. ४१, २.

तिष्ठध्वं ७. १०४, १८.

तिष्ठन् ६. ७५, ६; १०. १२३, ३.

तिष्ठंत १०. ११७, ५.

तिष्ठंतं १०. ८७, ६.

तिष्ठंतां ३. १८, २.

तिष्ठंति ८. ६८, १४.

तिष्ठंति १. १६४, ३६; ९. ८३, २; १०. १०, ८; ८५, १.

तिष्ठंतीः १०. ६७, ४.

तिष्ठंतु ९. ६९, ७; ८६, ३७.

तिष्ठंते १०. २५, २.

तिष्ठं ८. ३४, १८.

तिष्ठसि ८. १९, १०.

तिष्ठसि १. ५१, १२; २. २३, ३; ३. ६१, ३; १०. ८५, ४; ११८, २; १३५, ३.

तिष्ठसे ५. ८, ७; ९. ११०, ९.

तिष्ठाः ३. ८, १; १४, ४.

तिष्ठात् १०. ९५, १७.

तिष्ठाति ४. २०, २.

तिष्ठाति १. ८२, ४.

तिष्ठाते १. १२४, ११.

तिष्ठाथः ८. ९, ८.

तिष्ठे १०. १२५, ७.

तिष्ठेम १. ११०, ७; ८. २१, १२.

तिष्यः ५. ५४, १३.

तिष्यं १०. ६४, ८.

तिसृऽभिः ८. ६०, ९.

तिसृऽभ्यः २. ५, ५.

तिसृषु ६. ४७, ४.

तिसृणां ५. ६९, २; ८. १९, ३७; १०१, ६.

तिस्तिराणा १. १०८, ४.

तिस्तिरे ३. ४१, २.

तिस्थिपत् १. १६२, २०.

तिस्रः १०. ७०, ८.

तिस्रः १. १३, ९; ३४, ७; ८; ३५, ६; ७२, ३; १०२, ८; ११६, ४; १३३, ४; १६४, १०; २५; १७४, ७; २. ३, २; ८; २७, ८; ३५, ५; ३. २, ९; ४, ८; १७, ३; २०, २^{२}; ५६, २; ५; ४. ५३, ५^{२}; ५. ३५, २; ७. ३३, ७; ८७, ५^{२}; १०१, १; ४; १०४, ११; ८. २, ८; ५, ८; ३२, २२; ४१, ३; ९; १०१, १४; ९. ५, ८; ३३, ४; ५०, २; ९७, ३४; १०. ३३, ५; ६७, ४; १०७, ६; ११०, ८; ११४, २.

तीक्ष्णंऽशृंग १०. १५५, २.

तीक्ष्णेन॑ १०. ८७, ९.

तीर्थं १०. ४०, १३; ११४, ७.

तीर्थे १. ४६, ८; १६९, ६; १७३, ११; ८. ७२, ७; ९. ९७, ५३; १०. ३१, ३.

तीव्रः २. ४१, १४; ६. ४७, १; ९. १७, ८; १०. ७२, ६.

तीव्रं ४. ३५, ६; ५. ५, १; ३७, ४; ९. ६५, १५; १०. २७, २.

तीव्रऽसुतै ६. ४३, २.

तीव्रस्यं १०. १६०, १.

तीव्राः १. २३, १; ५. ३०, १३; ६. ७५, २; ८. २, १०; १०. ४२, ८.

तीव्रान् ६. ७५, ७; १०. ४२, ५.

तीव्रैः १. १०८, ४; ८. ६२, ५; १०. ४३, ६.

तु १. ५, १; १०, ११; २९, १–७; ६९, ४; १३२, ३; १६९, ४; १७७, ४; ३. ३०, २; १२; ३६, ९; ५०, २; ५१, १०; ४. १, १०; २२, ५; ५. २, ७; ६. २१, ८; २३, ७; २९, ५; ३६, ५; ४८, ९; ७. २९, १^{२}; ३१, ४; ८६, १; ८. १, १०; २६; २, २२; ७, ११; १३, १४^{२}; २१, १०; २७, १४; ३२, २४; ५१, ४; ६९, १६; ८२, ४; ९५, २; ९. ७२, ८; ९; ८७, १; ९७, ३८; १०. १, ५; ६; ८५, ३५; ८८, ६; १०१, १०.

तुग्रः १. ११६, ३.

तुग्रं ६. २०, ८; २६, ४; १०. ४९, ४.

तुग्रस्य ६. ६२, ६.

तुग्राय १. ११७, १४.

तुङ्यं ८. ३, २३; ७४, १४.

तुग्र्युऽवृधंः ८. १, १५.

तुग्र्युऽवृधं ८. ४५, २९; ९९, ७.

तुग्र्यासु १. ३३, १५.

तुग्र्यै ८. ३२, २०.

तुग्वंनि ८. १९, ३७.

तुचे ६. ४८, ९; ८. १८, १८; २७, १४.

तुच्छयान् ५. ४२, १०.

तुच्छयेन १०. १२९, ३.

तुर्जः १. १५१, ५; ३. ३४, ५.

तुजतः ३. ३९, ८.

तुजता १. ६१, ६; ९. ९१, ४.

तुजन् १. ६१, ६.

तुजे ३. ४५, ४.

तुजयंत्ऽभिः ७. १०४, ७.

तुजंये १०. ४९, ४.

तुजयै ५. ४६, ७.

तुजसे ४. २३, ७.

तुजा १. ५६, ३; ५. १७, ३; ६. ६८, २; ८. १७, १५.

तुर्जि ६. २६, ४.

तुजे ८. ४, १५.

तुजे ४. १, ३; ५. ४१, ९.

तुजेते इति १. ६१, १४.

तुज्यते १. ८४, १७.

तुज्यमानासः १. ११, ५.

तुज्याः ३. ६२, १.

तुज्यानि १०. १३८, ५.

तुंजते १. १३१, २.

तुंजंति ९. १५, ३.

तुंजंति ९. ७९, ५.

तुंजमानाः ३. १, १६.

तुंजाते इति १. १०५, २.

तुंजानः ९. ८७, ६.

तुंजानः ९. ५७, २.

तुंजेऽतुंजे १. ७, ७.

तुतुज्यात् १. १४३, ६.

तुतुर्यात् ६. ६३, २.

तुतुर्यात् ५. १५, ३; ७७, ४; ८. ९६, २.

तुतुर्याम ५. ४५, ११.

तुतुर्वणिः १. १६८, १.

तुतोदं १. १६२, १७.

तुद ६. ५३, ६.

तुदत् ८. १, ११; १०. ९६, ४.

तुदंतः १०. ९४, १४.

तुंदते १. ५८, १.

तुन्नः ९. ६७, १९; २०.

तुभ्यं १. ५४, ९; १३५, २; २. ११, ३; ३. ४२, ८; ५. ११, ५; ३०, ६; ७. २२, ७; ८. ५१, ९; ७६, ८; ८२, ५; ९. ६२, २७; ८६, ३०; १०. १६७, १.

तुभ्यं १. ६८, ३; ७१, ६; ८०, ७; १२१, ५; १२९, ३; १३४, ४^{२}; ५; १३५, १; १३९, ६; १७३, १३; २. २३, ४; ३६, १; ५^{२}; ३. १४, २; ४; ७; २१, ३; ४; २८, २; ३०, २०; ३५, ७; ८; ४७, ३; ५१, ६^{२}; ५२, २; ८; ६०, ६; ६२, ७; ४. २, ९; ३, १६; ६, ११; १७, १; ५०, ३; ५. १, १०; ६, ५; ११, ५; २९, ५; ४३, १५; ६. १७, ११; २०, २; १३; ४०, १; ४१, १; ४४, १०; २०; ७. १४, ३; १९, १०; २२, ७; २९, १; ३२, २१; ६४, ५; ८६, ३; ८; ९०, २; ८. २, ३०; ६, ३३; १२, २९; ३३, १२; ३९, ३; ४३, १८; २९; ६०, १८; ९३, २५; ९. ३१, ३^{२}; ५; ६२, २७; ६६, ६; ८८, १; ९४, ५; १०. ७, २; ५१, ९; ५६, २; ८५, ३८; १०४, १^{२}; २; ३; ११६, ७^{२}; १४८, ३; ४; १६०, १; २^{२}.

तुम्रः ३. ५०, १.

तुम्रं ४. १७, ८; १८, १०; ६. २२, ५; १०. २७, २; ८९, ९.

तुरः १. १८, २; १२१, ३; १७३, ९; ६. २५, ५; ४४, ३; ७. ४१, २; ८६, ४; ८. ३, १३; ४१, ८; १०. २५, १०.

तुरःऽपेये १०. ९६, ८.
तुरऽगातु १. १६४, ३०.
तुरणे १. १२१, ५.
तुरण्यतः ४. ४०, ३.
तुरण्यति ४. ४०, ४.
तुरण्यन् १. १२१, १.
तुरण्यन् १०. ६१, ११.
तुरण्यवः १. १३४, ५; ७. ५२, ३; ८. ५१, १०.
तुरण्युऽसत् ४. ४०, २.
तुरतः ६. १८, ४.
तुरं ४. ३८, ७; ५. ८२, १.
तुरं ७. ५६, १९; ८. ६६, ५; ७९, २.
तुरयन् ४. ३८, ७.
तुरयंतं ८. ९९, ६.
तुरयंते २. ३४, ३.
तुरऽयाः ४. २३, १०.
तुरस्य १. ६१, १३; ९६, ८; ५. ४३, ९; ८६, ४; ६. १८, ४; ४४, ५; ७. २२, ५; ८. २६, ४; ७८, ७.
तुरा १०. ९६, ७.
तुराः ८. २७, ६.
तुराणां १. १७१, १; ५. ४१, ५; ६. ४८, १२; ७. ४०, १; ५६, १०; ५८, ५.
तुराय १. ६१, १; १२१, ७; ४. २, ८; ६. ३२, १; ४९, १२; ६६, ९; १०. ७३, १.
तुराषाट् ३. ४८, ४; ५. ४०, ४; ६. ३२, ५; १०. ५५, ८.
तुरासः १. ६८, ५; ५. ४२, ५; ७. ५१, १; १०. ४९, ११.
तुरासः १. १६६, १४; ३. ५४, १३; ७. ६०, ८; १०. ३५, १४.
तुरीपं १. १४२, १०; ३. ४, ९.
तुरीय ८. ५२, ७.
तुरीयः ४. ४५, १; १०. ८५, ४०.
तुरीयं १. १५, १०; १६४, ४५; २. ३७, ४; ८. ३, २४; ८०, ९; ९. ९६, १९; १०. ६७, १.
तुरीयेण ५. ४०, ६.
तुरेभिः ३. ४, ११.
तुरैः १०. ३१, १.
तुर्फरी इति १०. १०६, ६; ८.
तुर्फरीतू इति १०. १०६, ६.
तुर्याम ५. ९, ६; ७०, ३; ६. ४, ५.
तुर्यै १०. १०६, ४.
तुर्वः १०. ६२, १०.
तुर्वणिः १. ५६, ३; ६१, ११; १२८, ३; १३०, ९; १८६, ३; ४. २०, १; ५. ३५, ३; १०. ३२, ५.
तुर्वणे ६. ४६, ८; ८. ९, १३; १२, १९; ४५, २७; १०. ९३, १०.
तुर्वीयाणं १. ५३, १०.
तुर्वशः ७. १८, ६.
तुर्वशं १. ३६, १८; ५४, ६; १७४, ९; ६. २७, ७; ४५, १; ७. १९, ८; ८. ४, ७; ७, १८; ९. ६१, २; १०. ४९, ८.
तुर्वशाय ५. ३१, ८.
तुर्वशायदू इति ४. ३०, १७.
तुर्वशे १. ४७, ७; ८. ४, १; ९, १४; १०, ५; ४५, २७.
तुर्वशेषु १. १०८, ८; ८. ४, १९.
तुर्वीतये १. ६१, ११; २. १३, १२; ४. १९, ६.
तुर्वीतिं १. ३६, १८; ५४, ६; ११२, २३.
तुविऽओजसं ४. २२, ८.
तुविःऽतमः १. १८६, ६.
तुविःऽतमा ५. ७३, २.
तुविःऽतमाय १. १३०, २.
तुविऽकूर्मिः ३. ३०, ३; ८. २, ३१; १६, ८.
तुविकूर्मिऽतमः ६. ३७, ४.
तुविऽकूर्मिन् ८. ६६, १२.
तुविऽकूर्मि ६. २२, ५; ८. ६८, १; ८१, २.
तुविक्रतो इति तुविऽक्रतो ८. ६८, २.
तुविऽक्षं ८. ७७, ११.
तुविऽग्रये २. २१, २.
तुविऽग्राभं ६. २२, ५.
तुविऽग्रीवः ५. २, १२; ८. १७, ८; ६४, ७.
तुविग्रीवाःऽइव १. १८७, ५.
तुविऽग्रेभिः १. १४०, ९.
तुविऽजात १. १३१, ७; २. २८, ८; ३. ३२, ११; ४. ११, २; ५. २, ११; १०. २९, ५.
तुविऽजातः १. १९०, ८; २. २७, १; ४. ५०, ४.
तुविऽजातयोः ७. ६६, १.
तुविऽजातस्य १. १३८, १; ५. २७, ३; ६. १८, ४.
तुविऽजाताः १. १६८, ४.
तुविऽजाताः १०. ६३, ६.
तुविऽजातौ १. २, ९.
तुविऽदेष्णं ८. ८१, २.
तुविऽद्युम्न १. ९, ६; ३. १६, ३; ६; ६. १८, ११.
तुविऽद्युम्नं ९. ९८, १.
तुविऽद्युम्नस्य ४. २१, २; ६. १८, १२; ८. ९०, २.
तुविद्युम्नाः ५. ८७, ७.
तुविऽद्युम्नासः १. ८८, ३.
तुविऽनृम्ण ६. ४६, ३.
तुविऽनृम्ण ४. २२, ६; ६. ३१, ५; ८. २४, २७; ७०, १०; १०. १४८, १.
तुविऽनृम्णः १०. ६१, ३.
तुविऽनृम्णं १. ४३, ७.
तुविऽप्रतिं १. ३०, ९.
तुविऽबाधं १. ३२, ६.
तुविऽब्रह्माणं ५. २५, ५.
तुविऽमघ १. २९, १–७; ८. ९२, २९.
तुविऽमघः ८. ६१, १८.
तुविऽमघं ८. ८१, २.
तुविऽमघस्य ५. ३३, ६.
तुविऽमघासः ५. ५७, ८.
तुविऽमन्यवः ७. ५८, २.
तुविऽमात्रं ८. ८१, २.
तुविऽम्रक्षः ६. १८, २.
तुविऽम्रक्षासः ६. ६, ३.
तुविऽरवे १०. ९९, ६.
तुविऽरवान् १०. ६४, ४; १६.
तुविऽराधसः ४. २१, २; ५. ५८, २.
तुविऽराधसं ७. २३, ५.
तुविऽवाजाः १. ३०, १३.
तुविऽवाजेभिः ६. १८, ११.
तुविऽशग्म ६. ४४, २.
तुविऽशुष्म ८. ६८, २.
तुविऽशुष्मः २. २२, १.
तुविऽशुष्मा ६. ६८, २.

तुविश्रवःऽतमः ३. ११, ६.
तुविश्रवःऽतमं ५. २५, ५.
तुविष्मः ७. २०, ४.
तुविष्मान् १. ५५, १; १६५, ६; १९०, ३; ८; २. १२, १२; ४. ५, ३; २९, ३; ७. ५६, ७; ५८, १; ८७, ६; १०. ४४, १; ७४, ६.
तुविऽस्वनः १. १६६, १.
तुविऽस्वनसः ४. ६, १०.
तुविऽस्वनसं ५. ८, ३.
तुविऽस्वनि ५. १६, ३; ६. ४८, १५; ९. ९८, ९.
तुविऽस्वनिः १. ५८, ४; १२७, ६; २. १७, ६; ५. ५६, ७.
तुविऽस्वनीनां ८. ४६, १८.
तुपर्यंती १०. २७, १६.
तुस्तर्वत् ८. ८, १६.
तुस्तुऽवांसः १. ८९, ८; २. २८, २; ७. ७६, ६.
तुस्तुवानाः ७. ५१, ३.
तुस्तुवुः ८. ६, १२; १८.
तूताव १. ९४, २.
तूतुजान १. १२९, १.
तूर्तुजानः १. ३, ६; ६१, १२; ६. २९, ५; ३७, ५.
तूतुजानः ८. १३, ११; १०. ४४, १.
तूर्तुजाना ७. ८४, ५.
तूर्तुजानाः ७. ६७, ६.
तूर्तुजिः ४. ३२, २; ७. २८, ३.
तूतुजिः १०. २२, ३.
तूर्तुजिं ६. २०, ८; १०. ३५, ६.
तूतुमा १०. ५०, ५; ६.
तूतूर्पंति १०. १००, १२.
तूतोत् २. २०, ५; ७.
तूतोरिति तूतोः ६. २६, ४.
तूर्यं ३. ४३, ३; ५२, ८; ५३, १६; ४. २६, ५; ५. २९, ७; ६. ५, ६; २२, ११; ७. २९, २; ५९, ४; ८. १, ९; ४, ३; ८; ५, ७; १३; २२, १०; ६५, १; ९; १०. १०, ८; १०४, १; ११०, ८; ११२, २.
तूर्यान् १०. २८, ३.
तूर्णयः १. ३, ८.
तूर्णांशं ८. ३२, ४.
तूर्णिऽअर्थः ३. ५२, ५.
तूर्णिऽअर्थाः ५. ४३, १.
तूर्णिः ३. ११, ५; १०. ७३, ४; ८८, ६.
तूर्णिऽतमः ४. ४, ३.
तूर्णि ३. ३, ५; ५१, २.
तूर्य ८. ९९, ५.
तूर्वंतं ६. ५०, १०.
तूर्वंथ ८. २०, २४; ७४, १०.
तूर्वन् १. १००, ५; ६. १५, ५; २०, ३.
तूर्वतः ६. १४, ३.
तूर्वयाणः १०. ६१, २.
तूर्वयाणं १. १७४, ३; ६. १८, १३.
तूर्वये ९. ४२, ३.
तूर्वसि ८. ९९, ६.
तूर्षु १. ११२, ४.
तूष्णीं २. ४३, ३.
तृंहत् १०. १०२, ४.
तृक्षिं ८. २२, ७.
तृक्षौ ६. ४६, ८.
तृणत्ति ८. १०३, ५.
तृणं १. १६१, ११; १६२, ८; १६४, ४०; १०. १०२, १०.
तृणऽस्कंदस्य १. १७२, ३.
तृणा ३. २९, ६.
तृणेषु १. १६२, ११.
तृतीयः १. १६४, १; १०. ८५, ४०.
तृतीयं १. १४१, २; १५५, ३; ५; २. १८, २; ४. ३४, ४; ३५, ९; ८. ५७, १; ९. ७५, २; ९६, १८; १०. १, ३; ४५, १.
तृतीये १. १६१, ८; २. ४, ८; ३. २८, ५; ५२, ६; ४. ३३, ११; ९. ७४, ६; ८६, २७; १०. ४५, ३; १२३, ८.
तृतीयेन १०. ५६, १; ६.
तृत्संवः ७. १८, १५; १९; ८३, ८.
तृत्संवे ७. १८, १३.
तृत्सुंऽभिः ७. ८३, ६.
तृत्सुंऽभ्यः ७. १८, ७; ३३, ५.
तृत्सूनां ७. ३३, ६; ८३, ४.
तृदिलाः १०. ९४, ११.
तृंधि ५. १२, २; ६. १७, २; ३; ५३, ५.
तृपत् २. ११, १५; २२, १; ३६, ५; ३. ३२, २; ७. ५६, १०; १०. ११६, १.
तृपलऽप्रभर्मा १०. ८९, ५.
तृपलं ९. ९७, ८.
तृप्णवः ३. ४२, २.
तृप्णुत १. ११०, १.
तृप्णुतं ८. ३५, १०.
तृप्णुहि २. १६, ६; ३६, ४.
तृप्रऽअंशवः १. १६८, ३.
तृप्ताः ७. ३८, ८.
तृप्तिः ९. ११३, १०.
तृप्तिं ८. ८२, ६.
तृप्राः ८. २, ५.
तृंप ८. ४५, २२.
तृंपतं ४. ४६, २; ८. ३५, २४.
तृंपतां ३. १२, ३.
तृंपतु १. २३, ७.
तृंपसि ८. ४, १२; ५३, ४.
तृंपसि ८. ७०, १०.
तृळ्हा ६. १६, ४८.
तृळ्हाः १. १३३, १.
तृषाणः ५. ३६, १; ८. ३३, २.
तृषाणा ७. ६९, ६.
तृषाणान् ४. १९, ७.
तृषितः १. १६, ५.
तृषु १. ५८, २; ४; ४. ७, ११; ७. ३, ४; १०. ७९, ५; ९१, ७; ११३, ८; ११५, ६.
तृषुऽच्यवसः ६. ६६, १०.
तृषुऽच्युतं १. १४०, ३.
तृषुणा ४. ७, ११.
तृषुं ४. ७, ११.
तृष्टऽअमया १०. ७५, ६.
तृष्टं ३. ९, ३; १०. ८५, ३४; ८७, १३.
तृष्टाः १०. ८७, १५.
तृष्णऽजः ७. ३३, ५.
तृष्णऽजे १. १०५, ७.
तृष्णऽजं १. ८५, ११; ५. ५७, १.
तृष्णया १. ३८, ६.
तृष्णा ७. ८९, ४; ९. ७९, ३.
तृष्यतः ८. ७९, ५.
तृष्यते १. ११६, ९; १७५, ६.

तृष्यंन् ८. ४, ३; १०.

तृष्यंतं **५.** ६१, ७.

तृष्याऽर्वतः **७.** १०३, ३.

तृष्वीं **४.** ४, १.

ते **१.** १४, ८; २०, ७; ३३, ४; ५; ८; ५३, ६^{२}; ५७, ४; ६४, २; ७३, ८; ८५, २; ७; १०; ८७, ३; ६^{३}; ८८, २; ९०, २^{२}; ३; ९४; १५; १०४, २; १०५, ११; १०६, २; १०९, ७; १११, ४; ११३, ११^{२}; १३१, ५; १३५, ८; १३९, ६; ९; ११; १४०, ५; १४१, ८; १५९, ३; ४; १६४, २३; ३६^{२}; ३९; ४७; ५०; १६७, ९; १६८, ९; १६९, २; ५; १७४, ४; १७९, २; १८६, ९; १८७, ५; **२.** ११, १३; १५, ५; २४, ६; ७; २७, ३; २९, ४; ३४, १२^{२}; १३; **३.** ४, ७; ८, ६; ७; २६, ५; ३२, ४; **४.** १, १४–१६; ४, १२; ५, १४; ८, ५; ६^{२}; १४, ४; ३३, ३; ८; १०; ११; ३४, १०; ३५, ८; ३७, २; ४२, ८^{२}; ५५, २; **५.** २, ५; ६, ६^{३}; ३०, २; ३१, १३^{२}; ३३, ३; ५; ४१, २; ४४, ११; ५०, २^{२}; ५२, २^{२}; ३; ८; ९; १२; ५३, ३; १५; ५९, ६; ६०, ७; ६१, १६; ६७, ४; ७०, २; ८७, ६; ७; **६.** १६, २७; ४७; १७, ४; २७, १; ४९, १^{२}; ५०, ११; १२; ५१, १०^{२}; ११; ५२, १५; ५५, ६; ६६, ६; **७.** १, ४; १७, ६; ७; २३, ५; २९, ४; ३०, ४; ३३, ९; ३५, १५; ३६, ७; ३९, ४; ४०, ४; ४३, ४; ४४, ३; ४७, ४; ४८, ३; ५६, २; १६; ६६, ९^{२}; ७६, ४; ५^{२}; ९०, ५; ९१, १; ३; ९३, ३; १०४, २४; **८.** ७, ८; १६, ५; १८, ५; १७; १९, १७; १८^{४}; ३५; २०, १२; २५, ११; १५; २७, १४^{२}; २८, ३^{३}; ३०, ३^{३}; ४३, २९; ४६, ३२; ४८, ५; ५३, ७; ५४, १; ६७, १४; ७२, १४; ७७, २; ८३, २; १०१, ६^{२}; १०३, १३; **९.** ८, २; १३, ५; ६४, ६; ६५, २४; ६७, १८; ७०, ३; ७३, ४; ७७, ३; ९८, ११; **१०.** १०, ३; १५, १; ३; ४; ५^{३}; ७; १२; १३; १७, ४; १८, १२; १९, ७; २०, ८; २१, २; २७, १५; ३२, २; ३५, १४; ३६, १०; १३; ४४, ६; ४८, ११; ५०, ३; ७; ६१, २७; ६२, ५^{३}; ६३, १; २; ७; ८; ६४, ६; ७; ६५, ३; ६७, ८; ७१, ९; ७३, २; ७४, ३; ७६, ७; ७७, २; ८^{२}; ८२, ४; ८७, २०; ९०, १६; ९२, १०; ९३, ४; ९४, ३; ८^{२}; ९; १०७, २; ३; ४^{२}; १०८, ८; १०९, १; १२४, ४; १२५, ४; १२६, ३; १२८, ६; ९; १४८, ३; १८१, २; ३.

ते॒ **१.** ४, ३; ४; ५, ७; ८, ९; ९, ४; ५; ११, २; ६; १४, २; ८; १६, ७; २४, ४–६; ९^{२}; १४; २५, १; ३; २८, ६; ३०, ४; ५; ९; १२; २०; २१; ३१, १८; ३२, १४; ३५, ११; ३६, २–४; १२; ४२, ५; ४३, ९; ४८, ४; ६; ४९, ३; ५१, ८; १०; १३; ५२, ७; १०; ११; ५३, ११; ५४, १; ८; ५५, ७; ८; ५७, २; ४; ५^{३}; ५८, ४; ५९, १; ५; ६१, १६; ६३, १; २; ९; ६८, २; ३; ६९, ४^{२}; ७३, १०^{२}; ७५, २; ३; ७६, १^{३}; ७९, २; ८०, ३^{२}; ८^{३}; १३; १४; ८१, २; ६; ९; ८२, १–६; ८३, ३; ८४, १; ३^{२}; १९; २०^{२}; ९१, ३; ४; ९; १६; १८; १९^{२}; ९४, ४; १०; ११^{२}; १४; ९५, ९; ९७, ४^{२}; १००, १७; १०१, १०; १०२, १^{२}; ३; ७; १०३, १; १०४, १; ६; ७; १०५, ८; १०६, ५; ११४, २; ३^{२}; ९^{२}; १०^{२}; १२१, ५; ८; १२; १५^{२}; १२३, ११; १२४, १२; १२७, ९^{२}; १३०, २; ६; १३१, ४; ५; १३२, २–४; १३३, ४^{२}; १३४; १; ६; १३५, १; ८; ९^{२}; १३८, ३; ४; १४०, ११^{२}; १४४, ६; १४७, १–३; १५०, ३; १५६, १; ३; १६२, ८; ९; ११; १४; १७^{२}; १९; २०^{२}; २१; १६३, १; ३; ४^{२}; ५^{२}; ६; ७^{२}; ८; १६४, ४९; १६५, ३^{२}; ९; १६७, १; १६९, ३; ४; १७०, ३; ४; १७३, ८^{३}; १२; १७४, ८; १७५, १^{२}; २; ५; १७६, ४; १७७, २; ३; १७८, १^{२}; १८७, ९; १८९, १; ४; १९१, ११; १४; १६; **२.** १, ७; ९; १५; २, १२; ४, ८; ६, २; ९, ३; ५; ११, १; ४; ६; ७; ११; १२; १३^{२}; १६; १९; २१; १२, १५; १३, १३; १४, १२; १५, १०; १६, ३^{२}; ६^{२}; ७–९; १७, ९; १८, ६; ९; १९, ७; ८^{२}; ९; २०, १; ९; २३, २; ४; १४; २८, ५; ७; ८; ३०, १०; ३२, ५; ३३, १; ७; ११; ३६, ५; ३७, ३; ४१, १; २; १८; **३.** १, २०; २३; ६, २; ५; ७; ९, २; १०, ३; १४, २; ३; ५; १७, ३; १८, २; ४; १९, २; ३; २०, २^{२}; २१, २; ५^{२}; २२, २; २७, ३; २९, १०; ३०, २; ३; ५; ६^{२}; ७; १९; ३१, १४; १७; ३२, १; २; ३^{२}; ९; ११; १२^{२}; ३३, ८^{२}; १०^{२}; ३४, २; ३५, १; ४; ५^{२}; ७^{२}; ९; ३६, ९; ३७, २; ३; ९^{२}; १०; ११; ३८, २; ३९, १; ४२, १; ६; ८; ४३, ७; ४४, १; ४६, १; ५^{२}; ४८, १; २; ५०, २; ५१, ११; १२; ५२, ४; ७; ५३, २; ५; ६; १४; ५५, २२^{३}; ५७, ४–६; ५९, २; ६२, ७; **४.** २, ६; ७; १९; २०; ३, २^{२}; ४^{२}; १५; ४, ३; ६; ८^{२}; १०; १५; ६, ६^{२}; १०; ७, २; ९; ९, ८; १०, १; ४^{२}; ६; ११, १; १२, १; २; ४; ५; १६, ७; ८; १०; १४; २१; १७, ४; १८; १८, ९; १२^{२}; १९, १०; २०, १०^{२}; २१, ९^{२}; १०; २२, ५; ७; २३, ६; २९, ५; ३०, २; १९; २४; ३१, ६; ९; १०;

३२, १०; ११; १८^{२}; १९; २२;
३५, ७; ४२, ७; ४७, १; ४८, ५;
५०, ३; ५४, ५; ६; ५८, ११^{२}; **५.**
१, १०; २, ११; ३, ३; ९; ४,
७; ६, ४^{२}; ७, ९; ८, ५; १०, ४;
११, ३; १२, ४–६; १५, ५; १८,
२; २०, २; ४; २२, ३; २५, ८;
२७, ३; २९, १३^{२}; १४; १५; ३०,
३; ३१, ४–७; १०, १३; ३२,
१२; ३३, ३–५; ३५, १–३; ४^{२};
३६, २; ४; ३८, १; ३; ५; ३९,
२; ३; ४२, ६; ४३, ३; ५; ४४,
२; ८; ५०, २; ५; ५६, २; ७८,
७; ८१, ५; ८४, ३; ८५, ८; **६.**
१, ४; ९; १०^{२}; १३; २, ४–६;
९; ३, १; ३; ४, ५; ५, ५; ७;
६, ३; ४^{२}; १०, ६; १३, ४; १५,
९; ११; १४; १६, १६–१८; २५;
२७; ३८; ४७; १७, ९; १०; १८,
३; ४; १३; १५^{२}; १९, ७; ९;
१०; १३; २०, १०; २१, ३–६;
२२, ४^{२}; २३, ६; २४, ३^{२}; ४^{२};
२५, १; ७; ८^{३}; ९; २६, ८;
२७, ३^{२}; ४^{२}; २९, ३; ५; ३१,
२; ३७, १^{२}; ४०, २; ४; ४१,
२^{३}; ३; ५; ४३, १; ४४, १; २;
११^{२}; २०; २१; ४५, ३०; ४७,
८; २२; २६; २९; ४८, १६; १८;
४९, १३; ५०, ९; ५३, ९^{२}; ५४,
९; ५६, ६; ५८, १^{३}; ३; ६१, १;
६४, २; ४; ६५, ५; ७५, १८^{२};
७. १, ८; ९; २०; २२; २५; ३,
२; ३; ४^{२}; ६^{२}; ८; ५, ६; १४,
२; १७, ७; १८, ३^{२}; १८; २०;
२१; १९, ६–८; ९^{२}; २०, ८^{३}; ९^{२};
१०; २१, ६^{२}; ७; ९^{२}; २२, १–३;
५^{२}; ६; ८^{२}; ९; २३, ४; २४, २;
६; २५, १^{२}; ३; २७, २; ५; २८,
१; २; २९, ३^{२}; ३०, ४; ३१, ७;
९; ३२, २; ६; १४; ३३, १०;
३६, ४; ३७, ३–५; ४२, २; ४६,
३^{२}; ४; ५४, २; ३; ७९, २; ८१,
४; ५; ८७, २^{२}; ८८, ५; ६^{२}; ९०,
२; ९२, १^{२}; ९५, ६; ९६, २; ५;
९८, ३; ६; ९९, १^{२}; २; ७; १००,
५; ६; १०४, १४; **८.** १, ३; ७;
९^{२}; १४; १६; ३०; २, १; ३; १०;
३०; ३, १; २; १०; १८; ४,
५–७; ९; १२; ६, १६; १९; ३१;
११, ५; ७; १२, ८; १०; २५;
२७–२९; ३१; १३, ४; ६; ११;
२२; २३; २६; ३१^{२}; १४, ३; ४;
६; १०; १५, ४; ६; १७, १; ५;
६^{२}; १०–१३; १९, १६; २०; ३३;
२१, ४; ५; ७^{२}; ८; १४; १५;
१६^{३}; २४, ५; ८; ९; १७; २६,
१०; ३२, ७; ८; ३३, ११; १२;
१५; १९; ३४, ५; ३६, १; ४०,
९; ४३, २; ३३; ४४, ४; २३–२५;
४५, ५; ६; १०^{२}; १२; १५; १९;
३२; ३६; ३९; ४२; ४६, ३; ८;
११; २५; ३२; ४८, ६; ७; ९;
१३; ४९, ५; ८; ९; ५०, ५; ९;
५१, ७; ५२, ७; ५३, ४; ६; ७^{२};
८; ५४, १; ५; ८; ५५, १; ५६,
१; ६०, १४; ६१, २; ९; १८;
६२, ४; ७; ८; १०; ६३, ५; ८;
६४, ९–११; ६५, ४^{२}; ८; ६६,
५; ११; ६८, ३; ८^{२}; ११; ६९,
१२; ७०, ५; ७१, ८; ७४, ७;
८; ७५, १०; १६^{२}; ७७, ९; ११;
७८, ४; ८०, ६; ७; ८१, ८; ९;
८२, ३^{२}; ७; ९; ८४, ४; ८८, ३;
६; ८९, २; ४; ६; ९०, ३^{२}; ६^{२};
९२, १६–१८; २३; २४; २६–२८;
९३, ४; ११; १२; २६; २७; ९५,
२; ५; ९६, ७–९; १२; ९८, ३;
११; ९९, ६^{२}; १००, १; २^{२};
१०१, ९; ११; १०२, १९–२१;
१०३, ४; **९.** १, ६; २, ७; ११,
२; १६, १; २९, ३; ३१, ३; ६;
५०, १; २; ५३, १; ५५, २; ५७,
१; ६१, १; ४; ५; १०; १७; १९;
२९; ३०; ६२, ७; २०; २८; ६३,
२२; ६४, २; ७; ११; २४; ६५,
९; १५; २८; ६६, ३; १०; १४;
३०; ६७, १२; १५; २३; २४;
७२, ४; ५; ७४, ९; ७५, ५; ७८,
२; ७९, ४^{२}; ५^{२}; ८२, ४; ८३, १;
८५, १; ८६, १; २; ४; ५; १३;
२८; ३७; ४७; ८७, ४; ८; ८९,
६; ९१, ५; ९६, २१; २४; ९७,
६; ३१; ४६; १००, ४; १०४, ४;
१०५, ४; १०७, २०; १०८, २;
१०९, २; ११; ११४, १; ४; **१०.**
४, १^{२}; ६; ७; ६, ७; ७, ६; १०,
२; ३; १२^{२}; १३; ११, ७; १२,
३; १४, ५; ११; १६, ३; ४^{३}; ५;
६; १७, १२^{३}; १८, १^{२}; १३^{३}; २०,
१०; २२, ९; ११–१३; २३, ६;
७; २५, १–३; २६, ८; २७, २;
२४; २८, ३^{२}; ५^{२}; २९, २; ३;
५; ६^{२}; ३३, ७; ३७, ३; ९; ३८,
२; ३; ४३, २; ५; ४४, २; ९^{२};
४५, २^{३}; ९; ४६, १; ४७, १;
५०, ३^{३}; ५–७; ५१, १; ७; ५४,
१–४; ५५, ४; ५६, १^{२}; २;
५७, ४; ५८, १^{२}; २–१२; ५९,
८; ६०, ८; ११; ६१, १८; २२;
६९, ३; ४; ९; ७३, ३; ७४, ४;
७५, २; ८१, ५; ८३, १; ६; ७;
८४, ३; ५; ८५, ४; ११^{२}; १२;
२१; २७; ३६; ४०^{२}; ८६, १३;
१५^{२}; ८७, ११; १९; २०; ८९,
१२; १४; १७; ९१, ४; ७; ९;
१५; ९३, ८; ९५, ५; १३^{२}; १८;
९६, १^{२}; १३; ९८, २; १००,
१२; १०२, १; १०५, ९; १०;
१०८, ५; ९; १११, १०; ११२,
१; २^{२}; ४; ५^{२}; ६–८; ११३, ३;
८; ११५, ४; ११६, ५; १२०, २;
५^{२}; १२२, ३; १२५, ४; १२७,
४; ८; १३३, ३; १३७, २; ४^{२};
६; १३८, ६; १४२, १–४; ६^{३};
८; १४४, १; ५; १४५, ६^{२};
१४७, १; १४८, ५; १५८, २;
१६०, ५; १६१, ५^{२}; १६२, १;
३^{२}; ४; १६३, १^{२}; २–५; १७३,
५^{२}; ६; १८०, १; १८४, १–३;
१८६, ३.

ते इति **१.** ६१, ८; १०४, ३; १६०,
१; ५; **२.** ३२, १; **३.** ५५, १२;

२०; ४. ४२, ३; ६. ७०, ४; ७५, ४; ७. ५३, १.
तेर्जः १. ७१, ८; ६. ३, ५.
तेजते १०. १३८, ५.
तेजंनेन १. ११०, ५.
तेजंमानः ३. ८, ११.
तेजंसा १. ५६, २; ६. ८, ५; १५, १९.
तेजंसे १. ५५, १; ३. २, १०.
तेजिष्ठया १. ५३, ८; २. २३, १४.
तेजिष्ठा ६. १२, ३.
तेजिष्ठाः ९. ७०, २.
तेजिष्ठाभिः १. १२७, ४; १२९, ५.
तेजिष्ठैः १०. ३, ५.
तेजीयसा ३. १९, ३.
तेतिंक्के ४. २३, ७.
तेनं १. २१, ६; ४७, ९; ४८, ११; ४९, २; ८२, ५; १०८, १; ११७, २; १२०, १०; १२५, १; १४०, ११; १६२, ५; १६४, ४२; १८२, २; २. २७, ६; ३. ६०, २; ४. ५७, ५; ५. २, ८; ३, ३; ३९, ३; ६२, ९; ८५, ३; ६. ४१, ४; ५६, १; ७. ४१, ५; ५५, ७; ६९, ५; १०१, ३^{2}; ८. ५, २०; ९, ५; १५; २०, २६; २२, ५; २९, ४; १०; ५४, ५; ६७, ६; ७७, ८; ९२, १६; ९. ६१, १९; ६६, ३०; ६७, २४; ११४, ४; १०. १०, ८; १७, १४; ३७, ४; ३९, १२; ४२, ७; ७५, ९; ९०, ७; १०२, ५; १०९, ५; ११२, २; १३०, ५; ६; १४२, ७; १५५, ३; १५६, १; १७४, १.
तपानः ८. ६०, १९; १०२, १६.
तेभिः १. ३५, ११; ७२, ६; ९१, ४; १०८, ५; १७०, २; १७७, २; २. ४१, १; ३. ३५, ९; ५१, ९; ६. २१, १२; ७. ३, ७; ९६, ५; ८. १, ९; २१, ४; ९. ६१, ५; ७५, ५; ११४, ३; १०. २, १; १५, ८; १४; ३१, १; ९२, ६; ९३, १; ९४, ९; ९८, १०; १०४, २; १४८, ४; १५५, १.
तेभ्यः ३. २, ६; ५. ७९, ७; १०. २८, ११; ६२, १; ८५, १७.
तेषां १. २, १; ११, ७; ४७, २; ८१, ९; १२५, ७; १३५, ५; १३९, ९^{2}; १६२, ६; १२; १६४, १५; १८८, ९; २. ३०, १०; ७. १९, १०; ५५, ६; ६६, १३; ९०, ४; ८. २०, १४; ६७, ३; १०. १४, ६; २८, ३; ६५, ३; ८२, २; ८७, १६; ९४, ८; ११५, ५; १८५, २.
तेषु १. १३९, ९; ५. ३१, १३; ४२, ८; ६. ५९, ४; १०. ११२, ७.
तोकं १. ४१, ६; ६४, १४; ९२, १३; २. २५, २; ५. ७७, ४; ६. १३, ६; ४८, १०; ७. १८, २३; ३६, ७; ५६, २०; ६०, ८; ८. ८४, ३; ९. ७४, ५.
तोकऽवंत् ३. १३, ७.
तोकऽसाता ६. १८, ६.
तोकऽसातौ १०. २५, ९.
तोकस्य १. ८, ६; ३१, १२; १००, ११; २. ९, २; ३०, ५; ४. २४, ३; ६. १९, ७; ४४, १८; ७. ८२, ९; ८. ६७, ११; ९. ६६, १८.
तोका ९. ९१, ६; १०. ४, ७.
तोकाय १. ४३, २; ७४, १७; ११४, ६; १८९, २; २. ३३, १४; ३. ५३, १८; ४. १, ३; १२, ५; ५. ५३, १३; ६९, ३; ६. १, १२; ५०, ७; ७. १८, २३; ५२, २; ६२, ६; ८. ५, २०; ९, ११; ६७, १२; ९. ६२, २; ६५, २१; १०. ३५, १२.
तोके १. ११४, ८; २. २, ११; ४. ४१, ६; ६. २५, ४; ३१, १; ७. ६७, ६; ८४, ५; ८. २३, १२; ७१, १३; १०. १४७, ३.
तोके इति १. १४७, १; ८. १०३, ७.
तोकेषु ७. ४६, ३.
तोकमऽइव १०. ६२, ८.
तोदः ४. १६, ११; ६. १२, ३.
तोदस्य ६. ६, ६; १२, १.
तोदस्यऽइव १. १५०, १.
तोशऽतमाः १. १६९, ५.
तोशते ८. ५०, ५; ९. २७, १; १०७, ९; १०९, २२^{2}.
तोशय ८. ५४, ८.
तोशसे ८. १५, ११; ९. ४५, २; ६३, २३.
तोशा ३. १२, ४.
तोशासा ८. ३८, २.
तौ १. २, ५; १०८, ३; १०९, ४; ५; १८४, १; २. ४०, ४; ५. ४०, ७; ७. ६५, २; ९४, १२; ८. २२, १३^{3}; १४^{2}; ४०, ३; १०. १४, १२.
तौग्र्यः १. ११७, १५; १८०, ५; १८२, ७; ८. ५, २२.
तौग्र्यं १. ११८, ६; १८२, ६; १०. ३९, ४.
तौग्र्याय १. १५८, ३; १८२, ५.
त्मन् ४. ४, ९; ५. ४३, ९; ६. १२, ३; ६८, ५; ९. ८८, ३.
त्मनं १. ६३, ८.
त्मना १. ३०, १४; ४१, ६; ५४, ४; ६९, ५; ७९, ६; १०४, ३; १३९, १०; १४२, १०; ११; १४४, ६; १५१, ६; १६८, ४; ५; १७८, ३; १८५, १; २. १, ६; २, ९; १९, ७; २५, २; ३२, ४; ३. ३, १०; ९, ५; ४. ६, ५; ४१, १०; ५३, १; ५; ५. ५, ९; १०, ४; १५, ४; २५, ८; ५२, २; ६; ८; ८७, ४; ७. ७, १; १८, २०; २०, १०; ३४, ५; ६; ५७, ७; ८४, १; ८. ३, २१; ६, ८; ४६, २७; ४९, ४; ८४, ३; ९४, ८; १०३, ३; ४; ९. ८६, १; १०२, ७; १०. २२, ५; ६४, ६; ६८, ७; ७७, ३; ११३, ३; १३३, ५; १४२, २; १४८, १; १७०, १; १७६, ३.
त्मनि १. १५८, ४; ४. २९, ४.
त्मने १. ११४, ६; १८३, ३; १८४, ५; ७. ६२, ६.
त्मन्या १. १८८, १०; १०. ११०, १०.

त्यजः ८. ४७, ७; १०. ७९, ६; १४४, ६.
त्यजसः १. १६९, १; ४. ४३, ४.
त्यजसं १०. १०, ३.
त्यजसा १. ११९, ८; १६६, १२; ६. ३, १; ६२, १०.
त्यत् १. ६१, १५; ६३, ४–७; ८८, ५; १००, १७; १०५, १३; १३९, २; १५१, २; २. २२, ४; ३. ६२, १; ४. ५, ९; १२, ६; ५१, १; ५. ६, १०; ४६, ५; ६. १८, ३; २०, १३; २७, ४; ४३, १; ४४, १६; ५१, १; ६२, ३; ६३, २; ७. ६६, १४; ६८, ६; ८. ६, २४; १५, ७; ३१, १८; ९. १११, २; १०. २६, २; ६८, ७; ८९, ८; ११२, ४.
त्यं १. १९, १; २०, ६; ३७, ११; ४२, ३; ५०, १; ५१, १; ५२, १; ६१, ३; ८०, ७; ११०, ३; २. ३०, ८; ४. ३०, १६; ५. १, ७; ३२, ४–६; ८; ६. १५, १७; २२, ६; ४४, ४; ५०, ६; ५१, १३; ७. ६८, ७; ८. २२, १; ६४, ५; ८६, ४; ९२, ७; ९४, १२; ९. ६, २; ३; १५, ८; ३८, ३; ६१, २; ७; ८४, ५; ९८, ७; १०८, ११; १०. ११, ४; ४१, १; ८०, ३; १४३, १; २; १७१, १; ३; १७८, १.
त्यस्य ५. ३२, ३.
त्यस्यै १०. ८६, २३.
त्या १. १२२, ४; ३. ३०, ३; ४. १५, ८; ३०, १७; १८; ५. ७३, २; ७४, २; ६. २, ९; ५०, १०; ६३, १; ७. ७३, ४; ८. १०, ३; १३, २७; १८, ८; १०. २२, ५; ६१, १५; ७५, ६; १३८, ६.
त्याः १. २९, ४; ९२, १; ८. ४८, ११; ९. ६३, ९; १०. १३४, ३.
त्यागं ४. २४, ३.
त्यान् ८. ६७, १; ९४, १०; ११.
त्याभिः ७. ८८, ५.
त्यां १. ६३, ८; १३९, ७.
त्ये १. ३७, १०; ५०, २; १०४, २; १८७, ४; ५; १९१, ५; ४. ६, ९; १०; ५. ६, ६; ७; ३३, ८; ४६, ६; ७. ३६, ७; ७५, ३; १०४, २०; ८. ३, १५; ७, ७; २२; २३, ११; ४३, ५; ९. २१, ७; ५१, ३; ९२, ४; १०. ३५, १; १२४, ५; १३८, १.
त्ये इति २. ३१, ५; ८. २, ४२.
त्येभिः १. ३०, २२.
त्रदं ८. ४५, २८.
त्रयः १. ३४, २^{२}; ८; ९; १२२, १५; १६४, ४४; ३. ५६, ८; ४. ४५, १; ५८, ३; ५. ६९, २; ७. ३३, ७^{२}; १०१, ४; ८. २, ७; ८; २८, १; ३०, २; ५७, २; ९. ९२, ४; १०. २७, २३; ४८, ७.
त्रयःऽत्रिंशतं १. ४५, २.
त्रययाय्यः ६. २, ७.
त्रयाणि १०. ४५, २.
त्रसदस्यवि ८. ४९, १०.
त्रसदस्युः ४. ३८, १; ५. २७, ३; ८. १९, ३६.
त्रसदस्युं १. ११२, १४; ४. ४२, ८; ९; ७. १९, ३; ८. ८, २१; ३६, ७; १०. १५०, ५.
त्रसदस्योः ५. ३३, ८.
त्रसन्ति ६. १४, ४.
त्रातः १. १२९, १०.
त्रातः ३. ५६, ६; ८. ६०, ५.
त्राता १. ३१, १२; १०६, ७; १२९, ११; १७८, ५; ४. ४, १०; १७, १७; ५५, १; ५. २४, १; ६. १, ५; २५, ७; ४८, २; ७. २०, १.
त्रातारः ८. ४८, १४.
त्रातारः ७. ५६, २२.
त्रातारं १. ४४, ५; २. २३, ८; ६. ४७, ११; ८. १८, २०; १०. १२८, ७.
त्रातुः १. १४५, ४; ४. ५५, ५.
त्रातृन् ६. ५०, १.
त्राध्वे २. २९, ६^{२}.
त्राध्वं ८. ३०, ३.
त्रां १. १००, ७; ४. २४, ३.
त्रामणे ५. ४६, ६.
त्रामंऽभिः १. ५३, १०.
त्रायतां १०. १३७, ५.
त्रायतां १. १०६, ७.
त्रायध्वं १०. ६३, ११.
त्रायध्वे ५. ५३, १५; ७. ५९, १; १०. ३५, १४.
त्रायतां १०. १३७, ५^{२}.
त्रायते ८. २७, १७.
त्रायमाणः ६. ५०, ८; ७. ३५, १०.
त्रायसे २. २३, ४; ८. ७१, ४; १०. ७, ४.
त्रायस्व ७. १९, ७.
त्रायस्व ७. १६, ८; १०. २२, १५; १४८, ४.
त्रायेतां १०. ३५, ३.
त्रायेथां ५. ७०, ३.
त्रासते १. १२८, ५; ७.
त्रासदस्यवं ८. १९, ३२; १०. ३३, ४.
त्रासदस्यवं ८. २२, ७.
त्रासाथे इति ५. ६२, ६.
त्रासीथां ४. ५५, १; ५. ४१, १; ७. ६२, ४; ७१, २.
त्रास्वे ८. ६१, १७; १०. ७, ७.
त्रिऽअनीकः ३. ५६, ३.
त्रिऽअरुणः ५. २७, १; ३.
त्रिऽअरुणाय ५. २७, २.
त्रिऽअरुषीणां ८. ४६, २२.
त्रिऽआविं ३. ५५, १४.
त्रिऽआशिरः ५. २७, ५.
त्रिऽउदायं ४. ३७, ३.
त्रिऽउधा ३. ५६, ३.
त्रिंशत् ३. ९, ९; ६. ५९, ६; ८. ३०, २; १०. १८९, ३.
त्रिंशतं १. १२३, ८; ३. ६, ९; ४. ३०, २१; ८. ७७, ४; ९. ५८, ४.
त्रिंशता २. १८, ५.
त्रिंशति ८. २८, १.
त्रिंशत्ऽशतं ६. २७, ६.
त्रिः १. २०, ७; ३४, १; २^{२}; ३^{३}; ४^{५}; ५^{५}; ६^{३}; ७; ८; ७२, ६; ११६, ४; १९; १४२, ३; १६२, ४; १९१, १२; १४; ३. ४, २; ५३, ८; ५४, ११; ५६, ५^{२}; ६^{२}; ८; ४. १, ७; १६; १२, १; ५३, ५; ५४, ६;

६. ४९, १३; ६६, २; ७. ११, ३; ८७, ४; १००, ३; ८. ३५, ७; ४१, ९; ४६, २६; ६९, ७; ९१, ७; ९६, २; ८; ९. ७०, १; ८६, १८; २१; १०. ६४, ८; ८७, ११; ९०, १५; ९५, ५; १२०, ३; १२२, ६.

त्रिःऽआश्रिं १. १५२, २.

त्रिऽककुप् १. १२१, ४.

त्रिऽकद्रुकेभिः १०. १४, १६.

त्रिऽकद्रुकेषु १. ३२, ३; २. ११, १७; १५, १; २२, १; ८. १३, १८.

त्रिऽकुशः २. १८, १.

त्रिका १०. ५९, ९.

त्रिऽचक्रः १. १५७, ३; १८३, १; ४. ३६, १.

त्रिऽचक्रं ८. ५८,३; १०. ४१, १.

त्रिऽचक्रेण १. ११८, २; १०. ८५,१४.

त्रितः १. ५२, ५; १०५, ९; १७; १६३, २; ३; १८७, १; २. ३१, ६; ३४, १४; ५. ९, ५; ४१, ४; १०; ५४, २; ८६, १; ९. ९५, ४; १०. ८, ७; ८; ४६, ३; ६; ९९, ६.

त्रिऽतंतु १०. ३०, ९.

त्रितं २. ३४, १०; ८. ४१, ६; १०. ६४, ३; ११५, ४.

त्रितस्य २. ११, २०; ८. ७, २४; ९. ३२, २; ३४, ४; ३७, ४; ३८, २; ८६, २०; १०२, २; ३.

त्रिताय २. ११, १९; ८. ४७, १४; १६; १०. ४८, २.

त्रिते ८. १२, १६; ४७, १३; १५; ५२, १.

त्रितेषु ६. ४४, २३.

त्रिऽदिवे ९. ११३, ९.

त्रिधा १. ११७, २४; २. ३, १०; ४. ५८, ३; ४.

त्रिऽधातवः ५. ४७, ४.

त्रिऽधातु १. ३४, ६; ७; १५४, ४; ३. ५६, ६; ४. ४२, ४; ६. ३५, २; ४४, २३; ४६, ९; ७. ५, ४; १०१, २; ८. ४७, १०; १०२, १४; ९. १, ८; ७०, ८; १०८, १२.

त्रिऽधातुः ३. २६, ७; ८. ७२, ९; ९. ८६, ४६.

त्रिऽधातुना १. १८३, १; ८. ४०, १२.

त्रिधातुऽभिः ९. १११, २.

त्रिऽधातु ८. ५१, ४.

त्रिधातुऽशृंगः ५. ४३, १३.

त्रिऽधातूनि १. ८५, १२; ८. ३९, ९.

त्रिऽनाके ९. ११३, ९.

त्रिऽनाभि १. १६४, २.

त्रिऽपंचाशः १०. ३४, ८.

त्रिऽपस्त्यं ८. ३९, ८.

त्रिऽपाजस्यः ३. ५६, ३.

त्रिऽपात् १०. ९०, ३; ४.

त्रिऽपाद् १०. ११७, ८.

त्रिऽपृष्ठः ९. ७१, ७; ७५, ३.

त्रिऽपृष्ठं ९. ९०, २; १०६, ११.

त्रिऽपृष्ठे ९. ६२, १७.

त्रिऽपृष्ठैः ७. ३७, १.

त्रिऽबंधुः ७. ३७, ७.

त्रिऽबर्हिषि १. १८१, ८.

त्रिऽभिः ८. ५९, ५.

त्रिऽभिः १. ३४, ११; ११६, ४; १५४, ३; १५५, ४; ३. २६, ८; ४. ५३, ५; ५. ३६, ६; ८. ३५, ३; ९. ६७, २६.

त्रिऽभ्यः ८. ७०, १५.

त्रिऽमंतुः १. ११२, ४.

त्रिऽमाता ३. ५६, ५.

त्रिऽमूर्धानं १. १४६, १.

त्रिऽयुगं १०. ९७, १.

त्रिऽवंधुरः १. ११८, १; १५७, ३; १८३, १; ७. ६९, २; ७१, ४; ८. २२, ५.

त्रिऽवंधुरे ९. ६२, १७.

त्रिऽवंधुरेण १. ४७, २; ११८, २; ८. ८५, ८.

त्रिऽवया २. ३१, ५.

त्रिऽवरूथः ६. १५, ९.

त्रिऽवरूथं ४. ५३, ६; ६. ४६, ९; ८. १८, २१; ४२, २; ९. ९७, ४७; १०. ६६, ५; ७; १४२, १.

त्रिऽवरूथेन ५. ४, ८; ६. २६, ७.

त्रिऽवर्तु ७. १०१, २.

त्रिऽविष्टि ४. ६, ४; १५, २.

त्रिविष्टिऽधातु १. १०२, ८.

त्रिऽवृत् १. १४०, २.

त्रिवृतः १. ३४, ९.

त्रिवृतं ९. ८६, ३२; १०. ५२, ४; ११४, १; १२४, १.

त्रिऽवृता १. ३४, १२; ४७, २; ११८, २; ८. ७२, ८; ८५, ८.

त्रिऽशताः १. १६४, ४८.

त्रिऽशीर्षाणं १०. ८, ८; ९९, ६.

त्रिऽशोकः १. ११२, १२; १०. २९, २.

त्रिऽशोकाय ८. ४५, ३०.

त्रिषु १. १५, ४; २४, १३; १०५, ५; १५४, २; १६४, ९; २. ३, ७; ३६, ४; ८. २, २१; ४५, ३४; ६९, ३.

त्रिऽसधस्थ ५. ४, ८; ६. ८, ७.

त्रिऽसधस्थः ६. १२, २.

त्रिऽसधस्थः १. १५६, ५; ४. ५०, १.

त्रिऽसधस्थस्य ८. ९४, ५.

त्रिऽसधस्था ६. ६१, १२.

त्रिऽसधस्थे १. ४७, ४; ५. ११, २; १०. ६१, १४.

त्रिऽसप्तैः १. १३३, ६.

त्रिऽस्तुप् १०. १४, १६; १३०, ५.

त्रिऽस्तुभः ९. ९७, ३५.

त्रिऽस्तुभं ८. ७, १.

त्रिऽस्थं १. ३४, ५.

त्री १. ३४, ९; ३५, ८; १४९, ४; १५४, ४; २. २७, ९; ३. ९, ९; २०, २[२]; ५६, ५; ४. ५३, ५; ५. २९, १[२]; ७[२]; ८[२]; ६९, १; ९. १७, ५; ७३, ८; ९७, ५५; १०३, २.

त्रीणां १०. १८५, १.

त्रीणि १. २२, १८; ९५, ३; १०२, ८; १६३, ३; ४[३]; १६४, ४५; ४८; २. २७, ८; ३. ९, ९; १७, ३; ३८, ६; ४. ५३, ५; ५. ६९, १; ८१, ४; ६. १७, ११; ५१, २; ७. ६६, १०; ८. ६, ४७; ७, १०; ८, २३; १२, २७; २९, ७; ३९, ९; ५२, ३; ९१, ५; ९.

१०२, ३; **१०.** ८, ९; ६७, ५; ८७, १०.

त्रीन् **१.** १२६, ५; १६४, १०; **२.** २७, ८; **३.** ६, ९; **४.** ३३, ५; **५.** ६९, १; **८.** ५, ८; ३९, ९; **९.** ७३, १.

त्रेतिनीं **१०.** १०५, ९.

त्रेधा **१.** २२, १७; ३४, ८; १५४, १; १८१, ७; **६.** ६९, ८; **७.** १०१, ४; **१०.** ४५, २; ७५, १; ८७, १०; ८८, १०.

त्रेधाऽईव **१.** ३४, ४.

त्रैतनः **१.** १५८, ५.

त्रैवृष्णः **५.** २७, १.

त्रैस्तुभं **१.** १६४, २३; **२.** ४३, १.

त्रैस्तुभात् **१.** १६४, २३.

त्रैस्तुभेन **१.** १६४, २४; **५.** २९, ६.

त्र्यंबकं **७.** ५९, १२.

त्वः **१.** १४७, २^{२}; १५२, २; **८.** १००, ३; **१०.** ७१, ४^{२}; ११^{४}.

त्वक् **९.** ७०, ७.

त्वक्षसा **१.** १००, १५; **४.** २७, २; **६.** १८, ९.

त्वक्षांसि **८.** २०, ६.

त्वक्षीयसा **२.** ३३, ६.

त्वचः **४.** १७, १४; **१०.** १७१, २.

त्वचं **१.** ७९, ३; १२९, ३; १३०, ८; **५.** ३३, ७; **९.** ४१, १; ७३, ५; ७४, ५; ८६, ४४; **१०.** १६, १; ३१, ८; ६८, ४; ८७, ५.

त्वचा **८.** १, ३२.

त्वचि **१.** २८, ९; १४५, ५; **३.** २१, ५; **९.** ६५, २५; ६६, २९; ६९, ३; ७९, ४; १०१, ११; १६.

त्वत् **१.** ५७, ४; ८४, ६; १९; **२.** २८, ६; ३३, १०; **३.** १४, ६; १७, ५; ३०, १; **४.** ११, ३^{४}; ४^{३}; २२, ६; ३०, १; **५.** २५, ७^{२}; ३१, २; **६.** ७, ३^{२}; १३, १; २१, १०; २४, ६; ३१, २; ३४, १; ६१, १४; **७.** ५, ३; ११, १; २१, ३; ३२, १९; **८.** १, १३; २४, ११; १२; १५; ४३, ३३; ६६, १३; ७८, ४; ९७, १४; **१०.** १८, १३; ९१, ८; ९८, २; ११२, ९; १७३, १.

त्वत **७.** १०१, ३^{२}; **१०.** ७२, ९.

त्वद्रिक् **५.** ३, १२; **१०.** ४३, २.

त्वं **१.** १, ६; ५, ६; ११, ५; ७; १२, ५; १४, ११; १५, ३; १८, ५; २५, २०; २७, ४; २८, ५; ३०, २२; ३१, १–८; ९^{२}; १०^{३}; १२–१५; ३३, ७; ३६, २; ६; १२; ४२, २; ४; ४४, १; ४५, १; ४८, १२; ४९, २; ५०, ६; ५१, ३; ४; ५^{२}; ६; ५२, १२; १३; १५; ५३, ८^{२}; ९; १०^{२}; ५४, ४; ६^{४}; ५५, ३; ५६, ६^{२}; ५७, ६; ६३, १; ३^{४}; ४; ५; ७; ८; ७५, ४; ७६, ५; ८०, ७; ८४, १९; ९१, १^{२}; २^{३}; ३; ५^{३}; ६; ७^{२}; ८; १०; २२^{५}; ९४, २; ३; ६; १५; १६; ९७, ६; १०२, ९; १०; १०४, ६; १२१, ९; ११–१४; १२३, ११; १२७, ९; १२९, १; ९; १०; १३०, ५; १३१, ७; १३४, ५; ६; १३९, ७; १४०, ११; १४१, १०; १४४, ६^{२}; १६५, ३; १६९, १; ४; ८; १७०, ५^{३}; १७१, ६; १७४, १^{४}; ९; १०; १७५, ३; १७८, ५^{२}; १८९, २; ३; ७; **२.** १, १^{७}; २^{२}; ३^{४}; ४^{४}; ५^{३}; ६^{४}; ७^{४}; ८^{२}; ९^{२}; १०^{४}; ११^{४}; १२^{३}; १४; १५; ७, ४; ५; ९, २^{३}; ४^{२}; ११, ४; १६, ६; १७, ८; २०, २^{२}; २३, ६; १९; २४, १५; १६; २७, १०; २८, १०; ३०, ८; ३३, १२; ३६, ५; ३७, ३; ४३, ३; **३.** १, २२; ६, ५^{२}; ९, २; १४, ६; ७; १५, २^{२}; ३; ५; १६, ३; १९, ५; ३०, ४; ३१, २०; ३२, ६; १०; ३५, ३; ६; ४१, ७; ४७, १; ५३, १८; **४.** १, ४; ५; २, २; १०; १२; १३; ३, ४; ५; ४, ११; ५, ११; ६, १; १६, १३; १७, १; ७^{२}; २०; १९, ५; ६; २०, ३; २२, १०; ३०, १; ५; ३२, ७; १३; ४२, ७^{२}; ४६, १; ५४, ३; **५.** २, २; ११; ३, १^{३}; २; ११; ४, ११; ८, ५; १०, २; १३, ४; ६; २०, १; २१, २; २३, २; २४, १; २८, ५; २९, १; ३०, ५; ३१, ८; ३२, १; २; ३३, २; ३५, ५; ४०, ७; ७८, ८; ७९, १०; ८१, ५; **६.** १, १^{२}; ५; ७; २, १^{२}; ६; ९; ३, १; ४, ४; ५, ३; ७, ३; ११, २; १२, ६; १३, २; ३; १५, २; ३; १२^{२}; १४; १६, १; ५; ६; ९; ३०; ३२; १८, ३; २०, ११; २१, ८; २३, १; २५, ३; २६, ३^{३}; ४^{३}; ५; ६^{२}; ३०, ५; ३१, ३; ४; ३३, २–४; ३६, ४; ४४, १२; ४५, ५; १७; ४६, २; ४८, ८; ९^{२}; १०; १९; ५०, ९; ६१, ६; ६४, ५; ७१, ३; ७५, १; **७.** १, २०; २१; २५; ५, ४; ६; ७; १२, ३; १३, २^{२}; १५, ८; १२; १६, ५^{३}; १०; १८, १; १९, ३; ४^{२}; २०, ९; २१, ३; २२, ७; २३, ४; २७, १; २; २९, ४; ३०, २^{२}; ३१, ३^{३}; ६; ३२, ११; १६–१८; ३७, ४; ६; ५५, ४; ९९, १; १००, २; **८.** १, २८^{२}; ३, १८; ४, ११; १६; ११, १^{२}; २; ३; १३, २६; ३१; १४, १; ११; १५, १०; ११; १६, १२; १७, ९; १९, ७; ८; १०; २५; ३०; ३१; २१, ६; १३; १७; २३, १२; २८; २९^{२}; ३०; २४, २६; २६, २०; २५; ३२, ७; ३३, ११; ३६, ७; ३७, ४; ५; ३९, ३; १०^{२}; ४३, १४; १५; ३२; ४४, ११; १४; २३^{२}; ४५, ६; ४८, ९; १३; १५^{३}; ५१, ६; ५२, ४; ८; ५४, ६; ८; ६०, ५; १२; ६१, ७; ८; १४; १६; ६२, ५; ११; ६४, ३^{३}; ६६, ६; १४^{२}; ७०, १०; ७१, २; ५; ६; ८; ७५, ३; ७८, ३; ७९, ३; ४; ८०, १; ८२, ७; ८४, ३; ६; ९०, २; ४^{२}; ५^{२}; ९२, ३२; ९३, १०; १३; १९; २१; ३३; ९५, ३; ९६, १७^{२}; १८^{२}; ९७, २; ७^{२}; १४;

९८, २^{२}; १०; ११^{२}; ९९, ५^{२}; १००, २; १०२, १; **९.** ४, ५; १६, ८; १८, २^{२}; २०, ५; २२, ७; २४, ४; ४५, २; ५१, ४; ५६, ४; ५९, ३; ६२, ९; २६; ६४, २५; ६६, ३; १८; ६७, १–३; २६; ८६, २३; २८^{२}; २९^{२}; ३०; ३८; ३९; ८८, १^{३}; ४; ९७, ४३; ४८; ९८, ४; १००, २; ३^{२}; ९; १०५, ६; १०७, ६; ७; २३; १०८, ३; ११०, ७; १११, २; **१०.** १, ४; २, १; ४, १; ४; ८, ४; १०, १४^{२}; १५, १२^{२}; १३; १६, १३; १८, ९; २१, ६; २२, ५; ८–१०; २५, ७; ९; २८, ३; ५; ४४, ५; ५०, ४; ५४, ४; ५^{२}; ५९, ५; ६१, २१^{२}; २२; ६९, ६; ८; ९; ७३, ३; ७^{२}; ८; ७५, २; ४; ६; ७९, ५; ८३, ३; ४; ८४, ३; ८५, २६; ४५; ८६, ४; ८; ८७, २०^{२}; २१; ८९, ८; ९१, ३; ९३, ११; ९५, १८; ९६, ५; ९७, १८; २३; १०२, १२; १०४, ९; १०८, ९; ११०, १; ३; ११३, १०; ११८, ७; ८; १२२, ५; १२४, ५; १२८, ६; १३३, २; ७; १३४, ४; १३७, ३; १४१, १; ६; १४५, ५; १४७, २; ५^{२}; १४८, २; १५३, २^{२}; ३–५; १६७, १^{३}; १७१, १–३.

त्वं **१.** ११३, ५; ६^{४}; **४.** १७, १३; **८.** ३७, ६^{२}; ७१, ५; ८.

त्वंऽत्वं **१०.** ९६, ५.

त्वऽर्यतायै **७.** २०, १०.

त्वया **१.** ८, ४; ३६, ४; ५३, ११; १०२, ४; १३२, १; १४१, ९; १७४, ६; १७८, ५; **२.** १, १४; ४, ९; ७, ३; २३, ९; १०; ३८, ७; ११; **३.** ३०, ९; **४.** ४, १४; २०, ३; **५.** ४, १; १३, ४; **६.** २६, ७; ३०, ३; ४५, १२; **७.** १५, ८; ३१, ६; ३२, २७; ४३, ५; ९८, ४; **८.** २१, ११; ६३, ११; ९२, ३२; **९.** ३५, ३; ८५, ८; ९६, ११; ९७, ५८; **१०.** ३८, ३; ४५, ११; ८३, १; ८४, १; ४; १२०, ५; १२८, १; १३८, ६.

त्वष्टः **२.** ३६, ३.

त्वष्टः **३.** ४, ९; **५.** ५, ९; **१०.** ७०, ९.

त्वष्टा **१.** ३२, २; ५२, ७; ६१, ६; ८०, १४; ८५, ९; १४२, १०; १६१, ४; ५; १६२, ३; १८६, ६; १८८, ९; **२.** १, ५; ३, ९; २३, १७; ३१, ४; **३.** ५४, १२; ५५, १९; **४.** ३३, ५; ६; **५.** ३१, ४; ४६, ४; **६.** १७, १०; ४७, १९; ५०, १३; **७.** ३४, २०–२२; **८.** १०२, ८; **९.** ८१, ४; **१०.** २, ७; १०, ५; १७, १; १८, ६; ४६, ९; ४८, ३; ४९, १०; ५३, ९; ६४, १०; ६६, ३; ९२, ११; १८४, १.

त्वष्टाऽइव **४.** ४२, ३.

त्वष्टारं **१.** १३, १०; २२, ९; **३.** ४८, ४; **५.** ४१, ८; **६.** ४९, ९; **९.** ५, ९; **१०.** ६५, १०; ११०, ९; १२५, २.

त्वष्टुः **१.** २०, ६; ८४, १५; ९५, २; ५; १६२, १९; **४.** १८, ३; **८.** २६, २१; २२.

त्वष्टुःऽमान् **६.** ५२, ११.

त्वस्मै **१०.** ७१, ४.

त्वस्यै **१०.** ५४, १.

त्वा **४.** २८, १; २; **७.** १, १३; **८.** ६८, ९; ९२, ३१.

त्वा **१.** १, ७; ४, ९; ५, ७; १०, १^{२}; ८; १०; १२; १४, २; ६; १५, १०; १६, १^{२}; ४; ९; १९, ९; २४, ३; ११; २७, १; ३०, १०; ३१, ४; १०; ३२, १२; ३६, ३; ४; १०; ४०, १; ४४, ७; ८; ११; ४५, ५; ७; ८; ४८, ११; ४९, १; ५०, ८; ५१, १०; ५२, ७; ५३, ६; ५४, ५; ५५, ७; ५७, ४; ५८, ६; ५९, २; ६०, ५; ६२, ११; ६५, १; ७०, ५; ७३, ४; ७६, २; ७८, १–४; ८०, २; ८१, ८; ८२, ३; ६; ८४, १; ४; ६; ९; ९१, ११; २३; ९४, ३; १०१, १०; १०२, ५; ७; १०३, ७^{२}; १०४, ९; ११४, ८; १२१, ११; १२५, २; १२७, २; ८; १२९, ४; १०; ११^{२}; १३०, १; २; १३१, २^{२}; ३; १३४, १; २; १३८, २^{२}; ३; ४^{२}; १३९, ६; १४१, १०; १४२, ४; १५०, १; १६२, १५; २०; १६३, ८; १६४, ३४^{२}; १७३, ७; १७५, ६; १७६, ६; १७७, २; १८७, २; ११^{२}; १९०, ५; १९१, १०–१३; **२.** २, २; ६, ३; ११, ११; १३, ५; २०, २; २३, १; ८; १४; १७; ३२, २; ३३, ४^{२}; ४२, १; २^{२}; **३.** १, १५; ६, ३; ७, २; ९, १; ६; १०, ९; १७, ४; १९, ५; २३, ४; २७, १०; १५; २९, ४; १६; ३०, १; ३२, १६; ३३, ११; ३६, ९; ३७, १; ४०, १; ४१, ९; ४२, ६; ४३, २; ३; ६; ४५, १; ४७, ३; ४^{२}; ५०, २; ५१, ४; ८; ११; ५२, ६; ८; ५३, २; ४^{२}; ६१, २; **४.** २, ८^{२}; ४, ७; ८; ९^{२}; १०; ७, २; १६, १९; १८, ८; ११; २२, ८; ३०, ३; ३१, २; ३२, ४; ८; १३; १५; ४८, ४; ५२, ४; ५७, ६; **५.** २, ८; ४, १०; ९, १; ११, ३; १३, १; २०, ३; २१, १–३; २२, ३; ४; २३, ३; २४, ४; २६, २–४; २९, १; ११; ३२, ११; ३६, २; ३; ५; ४०, ३; ५; ६१, ६; ७९, ४; ९; ८४, २; **६.** १, २; ६; २, ३; ४, ७; १५, १२; १५; १९; १६, ११; १४; २६; ३७; १७, ३; ४; ८; १३; १८, १४; १९, १२; २१, १; ६; ७; १०; २३, ८^{२}; २४, ६; २५, ५^{३}; २६, १; ३३, ४; ३७, १; ४०, ३; ४१, ५; ४४, १०; १२; १९; ४५, १०; २५; ५२, ३^{२}; ५३, १; ५६, ४; ६१, ५; ७५, १; १८^{२}; **७.** १, ११; ४, ६; १५, ७; ९; १६, ४; १८, ३; ४; १२; २१, १; २२, १; २३, ५; २४, ३; ५; २८;

१; २९, ४; ३०, २; ३१, ८; ९;
३२, १; १६; २२; २३; ३३, १०^{२};
११; ४१, ५; ५४, १; ७६, ६;
७७, ६; ७८, ५; ७९, ४; ८१, ३;
८६, ४; ८८, ७; ९९, ७; १००,
५; **८.** १, ३; १६; २०; २४; २५;
२९; २, ३; ११; २९; ३, ३; ९;
११; ४, २; ४; १४; १७; ६, १८;
२०; २७; ३८; ४२; ४५; ११, ८;
१२, २५; १३, ५; १३; १५, १२;
१७, २; ३; ७; १९, ३; १७; २६;
२१, २; ४; ६; २३, १६^{२}; १७^{२};
१८; २४, ६; २६; ३०; ३२, २३;
३३, १; २; ८; १४; ३४, २; ४; ८;
९; ४३, १२; १३; १७; २३; २८;
४४, ५; २२; ४५, ५; १३; १४^{२};
१६; १७; २०^{२}; २२–२४; ४६,
१७; ४९, ३; ५०, ४; ५१, ६;
५३, १; ६०, १; २; १५; १६;
६१, ३; ५; १४; ६४, १; २; ६;
६५, ३; ६; ६८, १; १०; ७०, ५;
७४, ११; १२; १५; ८१, २; ३;
८८, ३–५; ९०, ६; ९१, १^{२}; ३^{२};
९२, १२; ९५, १^{२}; २; ४; ९६,
४^{४}; ७; ८^{२}; ९७, ४; ९; ९८, ७;
८; १०२, १३; १७; १८; **९.** २,
४; ८; ८, ४; ५; ९; १६, ५; १७,
७; २६, ६; ३०, ५; ४८, १; ३;
५३, ३; ५६, ३; ६०, २; ६१,
२७; ६४, २३^{२}; ६५, ४; ११;
२७; ६६, ८; ९; ७९, ४^{२}; ८०,
२; ४; ५; ८६, ४; ३९; ८७,
१; ९२, ४; १०४, ४; १०७,
२; १०९, २१; ११०, २; **१०.** १,
४; २, ६; ७^{३}; ४, २; ३; १४, ४;
१६, ७; १२; १७, ३^{२}; ४^{३}; १८,
१०; २१, १; २२, ७; २६, ४;
२९, ३; ३२, २; ३७, ५; ७^{२}; ८;
४२, ३^{२}; ४५, ३^{२}; ४६, १०; ४७,
१; ८; ५१, ३^{२}; ५४, १; ६९, ४;
५; ७३, ८; ७५, ४; ८३, ५; ८५,
५; २२; २४^{३}; २६^{२}; ३६; ८७, ९;
१९; २२; २४; ८८, ५; ८९, १६;
९५, ७; ११; १५; १७; १८; ९६,
१; १२; ९८, ८; १०४, ६; १०५,
११; १०८, ९; ११५, ८; ९;
११६, ३; ८; ११८, २; ५; ९;
१२०, ४^{२}; १२२, ८; १२३, ६;
१२४, ६; १२८, १; १३१, ५;
१३३, २; १३४, १; १३७, ४; ७^{२};
१४०, ६; १४२, ६; १४५, ६;
१४६, १; १४७, १; १४८, १;
१४९, ५^{२}; १५०, २; १५५, १;
१६०, १; ५^{२}; १६१, १; ५^{२};
१६२, ५; ६; १७३, १^{२}; १७४,
३^{२}; १७९, २; १८३, १.
त्वाऽईषित: ८. ७७, १०.
त्वाऽऊंत: **१.** ७४, ८; **३.** १९, ३;
५९, २; **६.** १, ९; ३३, २; **८.**
५१, २.
त्वाऽऊंतय: **५.** ६५, ५; **९.** ६६, १४;
७६, ५.
त्वाऽऊंता: **१.** ७३, ९; **२.** ११, १६;
४. ४, १४; **५.** ३, ६; **६.** १६,
२७; १९, ७; १३; **१०.** १४८, १.
त्वाऽऊंतास: **१.** ८, २; ३; **४.** २९,
५; **८.** ६८, ९; **९.** ६१, २४;
१०. २२, ९.
त्वाऽदंत्त: **८.** ९२, १८.
त्वाऽदंत्तेभि: **२.** ३३, २.
त्वाऽदांतं **१.** १०, ७; **३.** ४०, ६; **५.**
७, १०; ३९, १.
त्वाऽदूंतास: **२.** १०, ६; **५.** ६, ८.
त्वाऽनिदं: **८.** ७०, १०.
त्वाभिं: **२.** २०, २.
त्वां **१.** २, २; ५, ८^{३}; ९, ४; ११,
२; ५; १२, ८; १४, ५; २५, १९;
३१, ११; ३६, १९; ४०, २; ४४,
५; ४५, ६; ४८, १४; ४९, ४;
५३, ११; ६३, ६; ७२, ३; ९१,
२१; १०२, ९; १०; १३०, ६;
१३४, ५; १४२, १३; **२.** १, ८^{२};
९^{२}; १३^{३}; ११, १; १७, ७; ८;
१८, ३; ३२, ३; **३.** ८, १; ११;
९, ७; १०, १; २; १७, ४; ३५,
९; ३७, ६; ४२, ९; ४३, १; ४;
४. १, १; ११, ५; १२, १; १६,
१८; १८, १२; १९, १; ३१, ७;
५. ३, ८; ४, १; ८, १–४; ६; ७,
९, १; ११, ५; ६^{२}; १३, ५; २१,
३; २९, ११; ३२, १२; ३५, ६;
६. १, ५^{२}; २, २^{२}; ४, ७; ७, ४;
९, ७; १५, ८; १६, ४; ७; १३;
२६, २^{३}; ३३, २; ४६, १^{३}; ६;
७. १, ३; ५, ५; ७, ७; ९, ६;
११, २; १२, ३; १७, ६; १८, ४;
२१, ८; २२, २; ६; ८८, ६;
८. १, ५; ६, १२; २१^{२}; ३७;
१५, ८; ९^{२}; १९, २९; २१, १;
२; ५; २६, २४; ३६, २; ३; ३९,
१०; ४३, २०; ४४, १९^{३}; ४६,
२; ५३, ८; ६०, १; ५; १०; ६२,
१०; ६७, १०; ७८, ९^{२}; ९२, १४;
२७; ३३; ९८, १२; ९९, १; **९.**
१, ५; ४, ९; ४५, ३; ६८, ७;
८६, २४^{२}; ३०; १००, ७; १०६,
८; १०७, २४; **१०.** १०, १३;
१४; २१, २^{२}; ६; २४, २; ३८,
५; ४२, ४; ४५, ११; ६९, १०;
७९, ६; ८६, ३; ९१, ९; ९८, ९^{२};
११२, ७; ९; १२२, ५^{२}; ७^{२}; १४७,
२^{२}; १५०, ३; १६०, २.
त्वांऽकामया **८.** ११, ७.
त्वाऽयुत: **१.** ५३, ३; **२.** २०, २; **६.**
२३, ७; **७.** १८, २.
त्वाऽयुता **६.** ४०, ३.
त्वायत्ऽभ्यं: **१.** १०२, ३.
त्वाऽयंत: **७.** १८, १२; **८.** २, १६.
त्वाऽयव: **१.** ३, ४; **३.** ४१, ७; **८.**
९२, ३३; **१०.** ९१, ९.
त्वाऽया **१.** १०१, ८; ९; **२.** १८, ६;
३. ४६, ५; **४.** २, ६; १४; **५.**
३२, १२; **६.** १, १३; **७.** १८,
२१; २९, ३; **८.** ६१, ९.
त्वाऽयु: **६.** ४७, १०.
त्वायुऽभिं: **४.** १६, १९.
त्वाऽवंत् **१०.** १००, १.
त्वाऽवंत: **१.** ९१, ८; **२.** २०, १; **४.**
३२, ६; **७.** २१, ८; २५, ४^{२}; **८.**
२, १३; २१, १५; ४५, ३२; ३५;
४६, १; **१०.** २९, ४.
त्वाऽवंसुं **७.** ३२, १४.

त्वाऽवान् १. ३०, १४; ५२, १३; ८१, ५; १६५, ९; १८९, ६; ६. २१, १०; ३०, ४; ७. ३२, २३; १०. ३८, ५.

त्वाऽवृधः १०. १४७, ४.

त्वाऽवृधा १. ५६, ४.

त्वाऽवृधेभिः १०. ६९, ९.

त्वाष्ट्रं १. ११७, २२; २. ११, १९; ३. ७, ४.

त्वाष्ट्रस्य १०. ८, ८; ९.

त्वाष्ट्रे १०. ७६, ३.

त्वाऽहतस्य ७. ३२, ७.

त्विषः ८. ४३, ३.

त्विषः ४. १७, २; ८. ९३, १४.

त्विषा ८. ७९, ८; १०. ७८, ६.

त्विषिः ५. ८, ५.

त्विषितः १०. ८४, २.

त्विषिं १. ७१, ५; ९. ३९, ३.

त्विषिऽमत् ३. ३१, १२.

त्विषिऽमतीं ५. ६३, ६.

त्विषिऽमते १. ५५, ५.

त्विषिऽमंतः ६. ६६, १०.

त्विषिऽमान् २. २२, २.

त्विषीः ९. ७१, ९.

त्विषे ५. ५२, १२; ७. ८२, ६.

त्विष्या १०. ८९, २.

त्वे १०. ७१, ७^{२}; ८.

त्वे इति १. २६, ६; ३६, ५; ६; ४८, १०; ५१, ७; ५९, १; ७२, ६; ७३, ७; ९४, ३; १६९, ५; १८७, ६; २. १, १३; १४; ५, ८; ९, ३; ११, १२; २८, ८; ४१, १७; ३. ११, ९; १९, ४; २०, ३; ४. २, ९; ३१, ६; ३२, ३; ४; १२; ५. ३, १; १०, २; ३३, ६; ६. १, ३; १३^{२}; ५, २; ११, ३; १२, २; ३४, १; ४७, १४; ७. १, १७; २१; ४, ४; ५, ६; ८, ५; ११, ३; १२, ३; १६, ७; १८, १^{३}; २१, ५; ८. ४, १६; १९, ८; १८; ४४, २८; ६१, ६; ६६, १२; ७८, ८; ९२, १४; ९७, १; ९९, २; १०३, ५; ९. १, ५; ११०, ७; १०. २१, ३; ४३, २; ४४, ४; ६९, ८; ९८, १०; १०५, ८; १२०, ३; १४०, ३; १४२, १.

त्वेन ४. १८, २^{२}.

त्वेषः १. ६६, ३; ७०, ६; १००, १३; २. ९, १; ३. २२, २; ५. ८७, ५; ६. २, ६; ३, ८; ६१, ८.

त्वेषथात् १. १४१, ८.

त्वेषऽद्युम्नाय १. ३७, ४.

त्वेषऽनृम्णः १०. १२०, १.

त्वेषऽप्रतीका १. ६६, ४; १६७, ५.

त्वेषं १. ३८, १५; ९५, ८; ११४, ४; ५; १५५, २; १६८, ६; ९; २. ३३, ८; ३. २६, ५; ५. ८, ६; ३४, ९; ५३, १०; ५६, ९; ५८, २; ८७, ६; ६. ४८, १५; २१; ७. १००, ३; ८. २०, १३; ४०, १०; ७४, १०; ९. ७१, ८; १०. ६०, २.

त्वेषऽयामाः १. १६६, ५.

त्वेषऽरथः ५. ६१, १३.

त्वेषऽसंदृक् ६. २२, ९.

त्वेषऽसंदृशः १. ८५, ८; ५. ५७, ५.

त्वेषऽसंदृशं १०. ६०, १.

त्वेषसा १. ६१, ११.

त्वेषस्य २. ३३, १४; ८. ४, १९.

त्वेषा १. १६८, ७.

त्वेषाः १. ३८, ७; १४३, ३; ८. २०, ७; ९. ४१, १.

त्वेषाभ्यां ८. ५९, ५.

त्वेषासः १. ३६, २०; ४. ६, १०.

त्वेषी ७. ६०, १०.

त्वेष्येण ७. ५८, २.

त्सरंत् ८. १, ११.

त्सरत् १. ७१, ५.

त्सरुः ७. ५०, १.

त्सारी १. १३४, ५.

द

दंष्ट्रा १०. ८७, ३.

दंष्ट्रैः २. १३, ४.

दंसः १. ६२, ६; ६९, ४; ११६, १२; ६. १७, ७.

दंसःऽभिः १. ११७, ४; ५. ७३, ७.

दंसना १. २९, २; ११९, ७; ३. ९, ७; ५. ८७, ८; ६. ४८, ४; ८. १, २७; ८८, ४; १०१, २.

दंसनाः १०. ४०, ९.

दंसनाभिः १. ११८, ६; ४. ३३, २; ६. १७, ६; ७. ६९, ७; १०. १३१, ५.

दंसनाभ्यः ३. ३, ११.

दंसनाऽवान् १. ३०, १६; ३. ३९, ४.

दंसनैः १. १६६, १३.

दंसयः १०. १३८, १.

दंससा ९. १०८, १२; १०. १३८, २.

दंसांसि १. ११६, २५; ५. ७३, २; ८. ९, ३.

दंसिष्ठ ८. २४, २५; २६.

दंसिष्ठं ८. २२, १.

दंसिष्ठा १. १८२, २.

दंसिष्ठौ १०. १४३, ३.

दंऽसु १. १३४, ४; १४१, ४.

दंऽसुजूतः १. १२२, १०.

दंऽसुपत्नीः ४. १९, ७.

दक्षं १०. ७२, ५.

दक्ष ३. १४, ७.

दक्षः १. ५९, ४; ९१, १४; २. २७, १; ७. ८६, ६; ८. ४८, ८; ९. ६१, १८; ६२, ४; ७६, १; ८५, २; १०. ७२, ४; १४४, १.

दक्षत ७. ३२, ९.

दक्षत ७. ९७, ८.

दक्षते ७. १६, ६.

दक्षऽपतिः १. ९५, ६.

दक्षऽपितरः ८. ६३, १०.

दक्षऽपितरा ७. ६६, २.

दक्षऽपितॄन् ६. ५०, २.

दक्षं १. २, ९; १५, ६; ५६, १; ७६, १; ८९, ३; ९१, ७; १३४, २; १४१, ११; १५१, ४; १५६, ४; ३. १३, २; ४. ३, १३; ५. ६८, ४; ६. १६, १७; ४४, ७; ९; ७. ३२, १२; ८. २४, १४; ४२, ३; ९३, २६; ९. ४, ३; ६५, २८; १०. २५, १; ३१, २; १२१, ८; १३७, २; ४; १३९, ६.

दक्षंसः ८. १३, १.
दक्षऽसाधनः ९. २५, १; २७, २; १०१, १५.
दक्षऽसाधनं ९. ९८, ८; १०४, ३.
दक्षसे १. १५१, ३; २. १, ११; ६. ४८, १.
दक्षस्य १. ५६, २; १३९, २; २. २१, ६; ३. २, ३; २७, ९; १०; ६२, १७; ४. १०, २; ५. १०, २; १६, २; १८, २; २०, ३; ३८, ४; ६६, ४; ६. १५, ३; २३, २; ५१, ६; ७. ६०, १०; ८. २५, ५; ६२, ६; ८६, १; ९. १६, २; १०. ५, ७; ६४, ५.
दक्षाः ४. २४, ९.
दक्षाणां १. ९५, ६.
दक्षात् १०. ७२, ४.
दक्षाय १. १११, २; ४. ३७, २; ५. ४३, ५; ८. ९, २०; ९. ३६, ३; ६२, २९; ९४, ३; १००, ५; १०५, ३; १०९, २; १०; १०. ३, १; ५७, ४.
दक्षाय्यः १. ९१, ३; १२९, २; २. ४, ३; ७. १, २.
दक्षाय्याय ७. ९७, ८.
दक्षासः १. ५१, २.
दक्षिणः १. ८२, ५.
दक्षिणतः १. ९५, ६; २. ४२, ३; ६. ३२, ५; ८. १००, २; १०. १५, ६; ८३, ७.
दक्षिणतःऽकपर्दाः ७. ३३, १.
दक्षिणऽत्रा ६. १८, ९.
दक्षिणं ६. ५४, १०; ८. २४, ५; १०. ४७, १; १६४, २.
दक्षिणया १. १२३, ५; १०. ६२, १; १०७, ६.
दक्षिणयाऽइव १. १६९, ४.
दक्षिणऽवान् ३. ३९, ६; ६. २९, ३.
दक्षिणा १. १८, ५; १२५, ५; १६८, ७; २. ११, २१; १५, १०; १६, ९; १७, ९; १८, ८; ९; १९, ९; २०, ९; ५. १, ३; ६. २७, ८; ६४, १; ७. २७, ४; ८. २४, २१; २९; ९. ७१, १; १०. ६१, ८; ६२, ९; ११; १०३, ८; १०७, ३; ७^{४}; ८.
दक्षिणा २. २७, ११; १०. १७, ९.
दक्षिणाऽआवृतः १. १४४, १.
दक्षिणाः ३. ३६, ५.
दक्षिणाभिः ३. ६२, ३; ८. ३९, ५.
दक्षिणां ६. ३७, ४; १०. १०७, ४; ५; ७.
दक्षिणायाः १. १२३, १; १६४, ९; ३. ५८, १; १०. १०७, १; ११.
दक्षिणाऽवत् ३. ५३, ६.
दक्षिणाऽवतां १. १२५, ६^{२}.
दक्षिणाऽवति ८. ९७, २.
दक्षिणाऽवते ९. ९८, १०; १०. १८, १०.
दक्षिणावत्ऽभिः १०. ६९, ८.
दक्षिणाऽवंतः १. १२५, ६^{२}; १०. १०७, २.
दक्षिणाऽवाट् ३. ६, १.
दक्षिणाऽवान् १०. १०७, ५^{२}.
दक्षिणित् ५. ३६, ४.
दक्षिणे १. १२८, ६; ३. ३९, ६; ६. २२, ९.
दक्षिणे १. १००, ९.
दक्षिणेन ८. २, ३२; ८१, १; ६; १०. १८०, १.
दक्षेण ४. ५६, ६; ९. ६८, ५.
दक्षेभिः १०. ११३, ९.
दक्षैः १. ६८, ४; ९१, २; ४. ५४, ३; ७. ६०, ६; ८. ७९, ४; ९. ६७, २६; १०. ९१, ३; ९२, १०.
दग्धा ५. ९, ४.
दध्म ७. ५६, २१.
दध्याः १. १२३, ५.
दंडाःऽइव ७. ३३, ६.
दतः ७. ५५, २.
दता १०. ११५, २.
दत्त १०. ५१, ८; ९७, १९.
दत्तं १. १६३, २; २. ३८, ११; १०. १०७, १.
दत्तं १. २४, ६.
दत्तस्य ८. ४५, ४२.
दत्ताः १. १२६, ३.
दत्तात् १०. १६, २.
दत्तां १०. ८४, ७.
दत्ते ९. ९६, १.
दत्ऽभिः ८. ४३, ३; १०. ६८, ६.
दत्रं ३. ३६, ९.
दत्रऽवान् ६. ५०, ८.
दत्राणि ८. ४९, २.
दत्रे ४. १७, ६.
दत्वते १. १८९, ५.
दत्वाय १०. ८५, ३३.
दद १. ३९, ९.
दद ४. ३६, ९; ५. ५७, ७.
ददः ७. २४, १; २९, १; ८. ४५, ३९.
ददत् २. ३०, ७; ५. २७, ४^{२}; ६१, १०; ७. २८, ५; ३२, ५; ४१, ३; ७५, ७; ८. २, ४१; ५, ३७; ६, ४८; २१, १८; ४६, २४.
ददत् ४. २४, १०; १०. १७, ३; ३०, ३; ८५, ४१^{२}.
ददतः १. ७३, ५; १८७, ५; ३. ५३, ७; ५. ३०, १२; ३३, ७; ७९, ५; ७. १९, १०; ३०, ४; १०३, १०; १०. ३२, ९; ६२, ७; १५१, २.
ददतं ५. ३२, १२.
ददता ५. ५१, १५.
ददतां ३. ५३, १७.
ददति ६. ४८, ८; ७. १६, १०; ३२, १५.
ददति २. ३५, १०.
ददतुः १०. ७३, ४.
ददते १. २४, ७.
ददथुः १. ११६, ६; ४. ३९, २; ५; ८. ८६, ३.
ददथुः १. ११६, २३; ११७, ७; ४. ३८, १; २; ४२, ९; ७. ७४, २; ८. ८६, २; १०. ३९, १०.
ददभंत १. १४८, २.
ददमानः ४. २६, ६.
ददमानात् १. ४१, ९.
ददर्श १. १०५, १८; १६४, ३२.
ददर्श १. १६४, ४; ४. १३, ५; ८.

१००, ३; **१०.** १०, ६; ५१, २; ७१, ४; १०२, १०.

ददृश्वान् **४.** ३८, ६.

ददात **७.** ५७, ६.

ददातन **१०.** ३६, १०.

ददाति **१.** ४०, ४; १२६, ६; **२.** १३, ३; **५.** ६, ३; २७, २; **६.** २८, ३; **८.** १, २१; **१०.** ११७, ३; ४.

ददाति **१.** ९१, २०; १३३, ७^{2}; **५.** २, १; २५, ५; ६; **६.** १४, ४; २७, ८; २८, २; **७.** २७, ३; **१०.** १४, ९; ८०, १; १०७, ७; ८; १६०, ३.

ददातु **२.** ३२, ४; **१०.** ५७, ५.

ददातु **१.** १५, ८; ४८, १३; **४.** ३०, २४; **७.** ४०, २; ६; **८.** ७१, १३; ९३, ३४; **९.** ९७, २१; **१०.** ५९, ७^{2}; ८७, १८; ११५, ५; १४१, २.

ददाथ **६.** २०, ११.

ददानः **५.** ३३, ९.

ददानः **५.** २, ३.

ददानं **१.** १४८, २.

ददाभं **५.** ३२, ७.

ददामहे **३.** २१, ५.

ददामि **१०.** ११६, ५.

ददारं **६.** २७, ४.

ददार्श **१.** ३६, ४; १४९, ५; १५७, ६; **२.** २७, १२; **६.** १०, ३; ७०, ३; **८.** १९, ५; २३, १५.

ददाश **६.** ३, २.

ददाशः **१.** ९४, १५.

ददाशत् **१.** ९१, २०; **५.** ३७, ५; **६.** ५, ५; **७.** २०, ८; **१०.** ७७, ७.

ददाशति **१.** १५६, २; **३.** १०, ३.

ददाशिम **१.** ८६, ६.

ददाशुः **१.** १४७, १; **४.** ८, ५.

ददाशुषे **१.** ११२, २०; १६६, ३; **२.** ८, २; **५.** ५३, ६.

ददासि **२.** ३२, ५.

ददासि **१.** १९०, ५.

ददिः **१.** १५, १०; ८१, ७; ११०, ७; **२.** १७, ८; ३७, १; २; **४.** २४, १; **६.** २३, ४; **८.** २१, ६; १७; २४, ३; ४६, १५^{3}; **१०.** १३३, ३.

ददीमहि **१.** ८, ३; **२.** २३, ९.

ददीरन् **७.** ४८, ४; ६४, १.

ददुः **२.** १३, १०; **३.** ५३, १६; ५८, ४; **५.** १८, ५; **८.** ६, ४७.

ददुः **५.** ५२, १७; **८.** ६२, ७; **१०.** १०९, ६; ११७, १.

ददुषः **१.** ५४, ८; **८.** ७९, ५.

ददुषां **६.** ८, ७.

ददृक्षे **७.** ७६, ३.

ददृक्षे **६.** ६४, २.

ददृऽवांसः **४.** १, १४.

ददृशानः **१.** १२७, ११; **४.** १७, १७; **९.** ७०, ६.

ददृशानऽपविः **१०.** ३, ६.

ददृशानं **४.** ७, १०.

ददृशुषीः **१०.** १३९, ४.

ददृशे **१.** १३५, ७; **५.** ४४, ६; **७.** ६१, ५; **८.** ७२, ६; ८२, ८; **९.** ९७, ९; **१०.** १११, ७.

ददृशे **१.** ९५, १; १६४, ४४; **३.** ५५, ८; **४.** ११, १; **६.** १०, ४; २७, ३; ४४, १०; ४८, ६; **७.** ९, २; ६२, १; **८.** १, ३४; ५७, २; **१०.** ४८, १०.

ददृश्रे **१.** २४, १०; **३.** ५४, ५.

ददृश्रे **३.** ८, १०; **१०.** ७१, ७; १४२, ५.

ददृश्वान् **४.** ३३, ६.

ददृहाणः **१.** १३०, ४; **४.** २६, ६.

ददृहाणं **१.** ८५, १०.

ददृहि **१.** १३३, ६.

ददे **४.** ३४, ४; ३७, ३; ४४, ५.

ददे **१.** १२६, ५; १८०, ६; **४.** १५, ८; **५.** ७, ३; १०; **७.** ६, ७^{2}; **८.** ६, ४६; १९, ३१; ४५, ४; ४६, ३२; ६३, ९; ६५, ११; ६८, १५; ७२, १७; ७८, १०; **९.** १०, ८; ६१, १०; ६८, ३; **१०.** ४८, २; ४९, २; ५५, ७; १३८, ४; १६६, ४.

ददौ **४.** ५, २.

दद्धि **१.** १७६, ४; **२.** १७, ७; **४.** २०, १०; **६.** २०, १; **१०.** ४७, ८.

दद्धि **४.** २०, ७; **८.** १२, ३३; १३, ५.

दद्मसि **८.** ४७, १५.

दद्महे **९.** ५८, ४.

दद्महे **९.** ५८, ३.

दद्राणं **१०.** ५५, ५.

दद्रिरे **७.** ९०, १.

दद्रुः **१.** ६२, ११; **४.** १९, ५.

दद्वहे इति **८.** ३४, १६.

दद्वान् **१०.** १३२, ३.

दध **८.** २७, १९.

दध **८.** १०२, १४.

दधः **७.** ३०, ३.

दधः **१.** ८१, ३^{2}; **७.** १७, ७; **८.** १३, २२.

दधत् **१.** ३५, ८; १२८, ३; १४०, ९; १८८, २; **४.** १५, २; ३; २०, ३; ५४, १; **५.** ६, १०; ३१, ११; **६.** ४५, २; **७.** २४, ४; **८.** ९३, २६; **९.** ३, ६; २०, ७; ६२, ३०; ६५, २१; ६६, २१; २७; ६७, १९; ६८, १०; **१०.** ३९, ५; १५६, ४; ५; १७०, १.

दधत् **४.** २४, ७; **५.** १४, १.

दधतः **१०.** २८, ८; ३४, ६; ४६, ४; ११४, ५; ६; १७५, ३.

दधतां **१०.** १८, ४.

दधति **१.** १६९, ३; **३.** ३०, १; **५.** ५४, २; **१०.** ९१, ९.

दधति **१.** ५५, ५.

दधती **७.** ७७, ५; **१०.** ९५, ४.

दधती **१.** ११६, १९.

दधतु **७.** ५१, १.

दधते **१.** ९४, २; **४.** ७, ९; **५.** ४१, २; **७.** २०, ६; ६८, ५; ९०, ६.

दधते **६.** १, ९; **९.** ६८, २; **१०.** ७७, ७.

दधतौ **७.** ७०, ४.

दधथः **४.** ४४, ४.

दधथुः **६.** ७२, ४.

दधन् **१.** ७१, ३.

दधन॑त् १०. ७३, १.
दधंति ७. ५६, १९.
दधंतु ७. ६२, ६.
दधन्युः ४. ३, १२.
दधनूऽवर्तः ६. ४८, १८.
दधन्वान् ९. ६७, २; १०७, १; १०. ११३, २.
दधन्विरे ४. ३१, ६; ९. १०, २; १३, ७; १०. १०४, १.
दधन्विरे ३. ६०, ३; ८. १९, १; १०. ९२, ५; ९६, ६; ७.
दधन्वे २. ५, ३; ३. ३१, १.
दधन्वे ८. ३३, १२; ९. ९३, २.
दधर्ष ५. ८५, ६; ६. ७, ५; ८. ९६, ९.
दधर्षति १. १५५, ५; ६. २८, ३; ७. ३२, १४; १०. १५५, ५.
दधर्षीत् १. १८३, ४; ४. ४, ३.
दध॑से ८. ३२, ६.
दधसे ६. १६, २७.
दधा॑त ५. २२, २; ७. ३२, १३; ३४, ४; ६; ९. २१, ५; ६.
दधात २. २९, ३; ४. ३३, ११; ५. ३, ७; ६. ६२, ८; ७. ५८, ३; १०. १५, ४; ७.
दधा॑तन १०. ३६, १३.
दधातन ५. ३४, १; ५५, ४; ८. ४७, १३; ९. ११, ६; १०. ९, १; १५, ११; ३७, ११; ६३, १५; १०१, ५; १२.
दधा॑ति १. १५५, ३; ४. १२, ३; ५. ४८, ४; ७. ९, १; १६, १२; ३८, १; ७५, ६; ९. ७४, ५; ७५, २; ८६, १०.
दधाति १. ६६, २; ४; १२५, १; २; १४६, २; ३. ५५, १७; ४. २०, ९; ५. ३, १०; ८३, १; ६. १०, ३; २८, २; ७. १, २३; ३२, १२; ७९, ३; ९५, ३; ९. ९४, ४; १०. ८५, १९; ८८, १९; १०९, ४; १२०, २; १६०, ४.
दधा॑तु ३. २६, ३; ४. ५३, ७; ७. ३४, २०.
दधातु १. ८९, ६; २. ४०, ६; ५. ५१, ११; ६. ५४, १०; ७. ३४, २२; ४५, ४; १०४, ९; १०. १७, ४; ६४, १३; ८५, ४७; १५८, ३; १६४, ३; १८४, १.
दधाते इति १. १८५, ६; ७; ५. ७७, १.
दधाते इति १. २, ९; १३६, २; १८५, २; १०. ५, ३.
दधा॑थ १०. ९५, ११.
दधाथ ४. ५, ६.
दधाथे इति ७. ७०, ३.
दधाथे इति १. १५१, ९; ३. ३८, ५; ७. ६१, ३.
दधा॑नः १. ३५, ४; ६७, २; ७२, १; १२८, ३; १४१, १३; १४४, १; १७१, ६; ३. १, ८; ३४, ५; ५५, १०; ४. १६, १४; २२, ३; २९, ४; ५. १, ५; १५, ४; ५; ६. ४४, ८; ७. ४५, १; ८. ४६, ५; ९. १५, ४; २३, ५; ३९, ३; ६३, १३; ६५, १०; ६६, ७; ९२, २; ९६, १२; ९७, ४७; ११३, १; १०. ७, २; ११, ७.
दधा॑नं ८. ९७, १३.
दधा॑ना १. ११७, ९; १२३, ४; ३. ५३, १६; ६. ६९, ३; ७४, १; ७. ६९, २; ७६, ७; ८०, २; ८४, १.
दधा॑नाः १. ४, ५; ६, ४; ५३, ११; ७३, ५; १०; १२२, ७; १४७, १; १६५, १२; २. ११, ४; ३. १, १६; ३८, ३; ५. ३, ४; ४१, १३; ६. ६६, ५; ७. ६०, ८; ७३, १; ९५, ५; ८. ६३, १०; ९. १७, ६; १०. १५, १०; ३९, १४; ६७, २; ७१, १; ८४, ७; १०४, ४; ५; १२१, ७; ८.
दधा॑नान् २. १२, १०; ६. ४७, २५.
दधानि १०. ११९, ९.
दधा॑ने इति १. १४६, ३; ६. ७०, ५; १०. ११०, ६.
दधाम ५. ४५, ५; १०. १०८, ३.
दधा॑मि २. ३५, १२; ८. ३४, ५; १००, २; १०. ९८, २.
दधामि ७. ३४, ८; ८. ९३, २७; १०. १८, ४; ८५, २४; १२५, २; १४७, १.
दधा॑सि १. ९४, १४; ८. १०२, १; १०. १४०, १; ५.
दधासि १. ३१, ७; ९१, ७; ५. ८, ५; १०. २१, ६; ८.
दधिऽआशिरः १. ५, ५; १३७, २[२]; ५. ५१, ७; ७. ३२, ४; ९. २२, ३; ६३, १५; १०१, १२.
दधिः १०. ४६, १.
दधिऽक्राः ४. ३८, ९; १०; ४०, ४; ७. ४४, ५.
दधिऽक्रां ३. २०, १; ५; ४. ३८, २; ३९, १; ५; ७. ४४, १; २.
दधिऽक्रावा ४. ४०, २; ७. ४४, ४.
दधिक्रावाऽइव ७. ४१, ६.
दधिऽक्रावाणं ७. ४४, ३.
दधिऽक्राव्णः ४. ३९, २–४; ६; ४०, १; ३.
दधिध्वं ६. १०, १; ७. ३४, ९; १०. १०१, ११.
दधिध्वे १. ३८, १; ४. ३४, ३; ३७, १.
दधिध्वे १. १६८, १; ५. ४, ३; ५५, २.
दधिम १०. ४२, ६.
दधिरे १. २६, ८; ४५, ७; १४८, ३; १५१, २; २. १३, १०; २३, १४; ३. १९, ४; ४. ८, ६; ५. १६, १; ६. ५, २; २५, ७; ३८, ३; ७. ५३, १; १०४, १८; ८. १२, २५; १०. ४६, १०; ६३, ५; ११४, ३.
दधिरे १. ३६, २; ५९, ३; ६४, १०; ७२, ३; ७३, ७; ८३, ४; ८५, २; ३; ८७, ५; १३१, १; २. २५, ५; ३४, १३; ३. १, ६; २, ५; ५०, ३; ५१, ६; ४. ५०, १; ५. ८, ६; १८, ४; ४४, ६; ५५, १; ६१, ११; ६. १५, ८; १७, ८; ३६, २; ४८, २१; ७. ११, ४; १७, ६; ३१, १२; ८. २, ३०; १२, २२; ५०, ४; १०. ५, २; ८,

३; ४५, ११; ४६, ८; ५२, ३; ९१, ६; ९४, ५.

दधिषे १. ८२, ६; ५. ३८, २; ६. ४३, ४; ७. २८, २; ९२, १; ९८, २; ८. ४५, ३१; ९७, २; १०. ५०, ६.

दधिषे १. ५७, ६; ६२, ९; २. १३, ६; ३. १८, ५; ५. ४५, ११; ६. १०, ६; ८. ४, ४; १०; १५, १०; ९. ६, ९; ६४, १; १०७, १०; १०. ८, ४; ६; २८, १२; ५४, ५; ७३, ३; ८; ९६, १०; १२०, ७.

दधिष्व ३. ३५, ६; ४०, ५.

दधिष्व १. ३, ६; १०, ९; ३. ३७, १०; ४२, ५; १०. ११६, ८.

दधीचः १. ८४, १३; ११९, ९.

दधीचे १. ११७, २२; १०. ४८, २.

दधीत १. ४०, २; ८. १९, ११; ७४, ९.

दधीत ५. ६६, १.

दधीत २. ३५, १; ५. ४१, ५; ६. १५, १५; ८. ७२, १३; १०. १०, १.

दधीमहि ५. ३५, ८; ५२, ४; ७. ४०, १.

दधुः १. ३६, १०; ५८, ६; १४८, १; ६. १५, २; ७. ६६, ११; ८. १३, २०; ९. ९९, ३.

दधुः १. ७२, १०; ७३, ४; ८०, १५; २. २, ४; ३. ३, ५; ४. ५५, २; ५. २, ६; ७९, ५; ७. ३२, २; ८२, २; ८. ७, २२; १३, २९; ९. ९, ५; ८३, ३; ११०, ७; १०. १८, १४; १४०, ३.

दधृक् ५. ६६, ३; ८. ८२, २; १०. १६, ७.

दधृषं ३. ४२, ६.

दधृषिः २. १६, ७.

दधृषिं ४. १७, ८.

दधृष्वणि ८. ६१, ३.

दधृष्वान् १. १६५, १०; ४. २२, ५; ५. २९, १४.

दधे १. २४, ४; ३०, ३; १०३, ४; १४९, ५; २. १९, १; २३, ६; ३४, ९; ३. २, १३; २२, १; ५. २३, ४; ८. ६, ११; १३, १९; ४१, ८; ५२, ३; ९. १८, ४; ९८, ८; १०. १२९, ७.

दधे १. ३, ११; २२, १७; ३६, १९; ४०, ७; ८; ५५, ८; ८१, ४; १२८, ६; १३९, १; १६८, ३; २. ८, ५; ३१, ६; ३२, १; ३. १, ३; २३, १; ४; २७, ९; १०; ३९, ६; ५५, १३; ६१, ७; ४. ३६, ६; ५. ५३, ५; ८१, १; ८६, ५; ७. ५०, १; ८. ३३, ७; ८; ३९, ४[2]; ४१, ३; ४४, ३; ९. ७३, ३; ८; ८२, ३; १०८, १२; १११, २[2]; १०. १९, ७; १००, ५.

दधौ १. ९५, ३; १०. २७, १३.

दध्नः १०. १७९, ३.

दध्ना ८. २, ९; ९. ११, ६; ८१, १.

दध्मः ५. १७२, ३.

दध्मसि ८. १०२, २०.

दध्मसि १. ५०, १२[2].

दध्यङ् १. ८०, १६; ११६, १२; १३९, ९; ४. १६, १४; ९. १०८, ४.

दध्रिरे १. ४८, ३.

दध्रे १. ३७, ७.

दध्रे ८. १७, १३; १०. ८२, ५.

दध्वसे १०. ११३, ७.

दन् १. १२०, ६; १४९, १; १५३, ४; १०. ६१, २०; ९९, ६; १०५, २; ११५, २.

दनः १. १७४, २.

दंतः ६. ७५, ११.

दंतं ४. ६, ८.

दंदशानाः १०. ९५, ९.

दभः ५. १९, ४.

दभत् १०. १०८, ४.

दभत् १. १७८, २.

दभन् १. ८४, २०; १४८, ५; २. ३२, २; ६. ४४, १२; ८. ४५, २३; १०. ८७, ९; १२०, ४.

दभंति ७. ३२, १२.

दभाति ६. २८, ३; १०. १६५, ३.

दभाय ५. ४४, २; ७. ९१, २; ९. ७३, ८.

दभीतये २. १३, ९; ४. ३०, २१; ६. २६, ६; ७. १९, ४; १०. ११३, ९.

दभीतिः ४. ४१, ४; ६. २०, १३.

दभीतिं १. ११२, २३; २. १५, ९.

दभीतेः २. १५, ४.

दभ्नुवंति १. ५५, ७.

दभ्यते १. ४१, १.

दभ्यं १०. १०८, ४.

दभ्याय १०. ६१, २.

दभ्रऽचेताः ८. १०१, १६; १०. ६१, ८.

दभ्रं १. ११३, ५; ४. ३२, २०; ७. १०४, १०; ८. ४५, ३२.

दभ्रस्य १. ८१, २.

दभ्राः ४. २५, ५.

दभ्राणि १. १२६, ७.

दभ्रेभिः १. ३१, ६; ४. ३२, ३; ७. ८२, ६; १०. ३८, ४.

दं ६. ३, ७.

दमन्यत् १०. ९९, ६.

दमे १. ७५, ५.

दमऽयन् ६. ४७, १६.

दमयंतं ७. ६, ४; १०. ७४, ५.

दमां १०. ४६, ७.

दमाय ३. ६, ३.

दमिता २. २३, ११; ३. ३४, १०; ५. ३४, ६.

दमूनसः ५. ४२, १२.

दमूनसं १. १४१, ११; ३. २, १५; ४. ११, ५; ५. ८, १; १०. ४१, ३.

दमूनसि ८. ५०, १०.

दमूनाः १. ६०, ४; ६८, ५; १२३, ३; १४०, १०; ३. १, ११; ३, ६; १७; ५, ४; ३१, १६; ४. ४, ११; ५. १, ८; ४, ५; ६. १९, ३; ७१, ४; ७. ९, २; १०. ३१, ४; ४६, ६; ९१, १.

दमे १. १, ८; ६०, ४; ६१, ९; ६७, ५; ७१, ६; ७३, ४; ९४, १४;

१४३, ४; १७४, ३; २. १, २; ७; ८; २, ४; ११; ४, ३; ३५, ७; ३. ३, ९; १०, २; २९, १५; ४८, २; ४. २, ८; ५, १५; ८, ३; ९, ४; ५. ४३, १२; ४८, ३; ६. १, ६; २, १०; १२, ४; ७. १, २; १९; १२, २; ४२, ४; ८. ७, १२; ४४, १५; ९. १११, २[२]; १०. ७, ४; ९१, १; १६७, ४.
दमेंऽदमे १. १२८, ४; ४. ७, ३; ५. १, ५; ६, ८; ६. ७४, १; ७. १५, २.
दमेषु २. ८, ३; ८. १०२, ११.
दंऽपतिं १. १२७, ८.
दंपती इति दंऽपती ५. ३, २; ८. ३१, ५; १०. १०, ५; ६८, २; ८५, ३२; ९५, १२; १६२, ४.
दंपती इवेति दंपतीऽइव २. ३९, २.
दुंऽपते ५. २२, ४; ८. ६९, १६; ८४, ७.
दुंभय ८. ४०, ६; १०. २२, ८.
दुंभयः १०. २२, ११.
दुंभयः १. ५४, ६.
दुंभयत् ६. १८, १०.
दुंभयन् १०. ११३, ९.
दम्यै ३. २, ८; ७. ५६, १४.
दम्याय ८. २३, २४.
दम्येभिः ३. १, १५.
दर्यते ८. १०३, ६.
दुयते ४. ७, १०; ५. ४९, ३; ६. ६, ५; ३०, १; ७. २१, ७; ८४, ४; १००, १; ८. २, ३१; ९. ९०, २; १०. ८०, २.
दुयध्वं ७. ३७, २.
दर्यंत ७. १६, ७.
दर्यमानः १. १०, ६; १२०, ३; १३०, ७; ३. २, ११; ३४, १; १०. २३, १.
दर्यसे २. १३, ६; ६. ३७, ४; ७. २३, ४; ५.
दुयसे २. ३३, १०; ६. २२, ९; १०. १४७, ५.
दुयस्व १. ६८, ३.
दुरयः १. ६२, ४.
दुरयस् १०. ९९, ११.
दुरयन् ७. ५, ३.
दुरयंतः १. ५३, ४.
दरीमन् १. १२९, ८.
दर्त् १. १७४, २; ६. २०, १०; २७, ५.
दुर्तरिति दर्तः १. १३०, १०.
दर्ता ६. ६६, ८.
दुर्ता ८. ९८, ६.
दर्षुं ६. २०, ३.
दर्दः ४. १६, ८.
दुर्दरिति दर्दः १. ६३, ७; ४. १६, १३; ६. २०, ७; ७. १८, १३.
दुर्दरीति ६. ७३, २.
दुर्दरीमि ८. १००, ४.
दुर्दर्तु ७. ५५, ४.
दर्दर्षि २. १२, १५.
दुर्दिरत् ८. ३२, १८.
दुर्दृहि ३. ३०, २१; ७. ५५, ४; ८. २४, १४.
दर्द्रत् ६. १७, ५.
दर्धर्षि ५. ८४, ३.
दुर्भासः १. १९१, ३.
दुर्मः ३. ४५, २.
दुर्मा १. १३२, ६.
दुर्माणं १. ६१, ५; १०. ४६, ५.
दर्विः १०. १०५, १०.
दर्वी इति ५. ६, ९.
दुर्शत १. २, १.
दुर्शतः १. १४४, ७; ३. १०, ६; २७, १३; ५. ५६, ७; ६५, १; ६. ३०, २; ८. ४१, ३; ४; ७०, २; ९. २, ६; १११, ३[२].
दुर्शतं १. ३६, ९; ३८, १३; १०२, २; ११७, ५; १४१, १; १६४, ५२; ३. १, ३; १३; २, १५; ४. ३६, ७; ५. ६६, २; ६. १, ३; ५१, १; ७. ६६, १४; ८. ७१, १०; ७४, ५.
दुर्शतऽश्रीः १०. ९१, २.
दुर्शतस्य १०. १४०, ४.
दुर्शता १. ६४, ९; ५. ८०, २; ६. ६४, ५; १०. ७५, ७.
दुर्शताः ३. ५७, ४.
दुर्शतात् १. ११६, ११.
दुर्शताभिः ६. ६३, ६.
दुर्शतायाः ७. ७५, ३.
दुर्शतासः ९. १०१, १२.
दुर्शते इति ९. ५, ६.
दुर्शथः ८. २६, ४.
दर्शन् १०. २७, ६.
दर्शनाय १. ११६, २३.
दर्शि १. २५, १८[२].
दर्शि ३. ५६, २.
दर्शि १०. १२३, २.
दश्यौ ५. ५२, ११.
दर्षत् १०. २७, ७.
दुर्षत् ९. ७४, ७; १०. २७, ७.
दुर्षते १०. १२०, ६.
दुर्षसि ८. ३२, ५.
दर्षि ६. २६, ५; ८. २४, ४.
दुर्षि १. ११०, ९; ४. १६, ८; ५. ३९, ३; ६. ३३, ३; ८. ६, २३; ३३, ३; ९. ६८, ७; १०. ६९, ३.
दुर्षीष्ट १. १३२, ६.
दविंद्युतत् ६. १६, ४५; ७. १०, १; १०. ४३, ४; ६९, १.
दुविद्युतत् १०. ९५, ३.
दविद्युतति ८. २०, ११.
दविंद्युतत्या ९. ६४, २८.
दविंद्योत् १०. ९५, १०.
दुविद्योत् ६. ३, ८.
दविधाव १. १४०, ६.
दविंध्वत् ४. १३, २; ८. ६०, १३.
दविंध्वतः २. ३४, ३; ४. १३, ४; ४५, ६; १०. ९६, ९.
दुविषाणि १०. ३४, ५.
दुविष्ठं ६. ५१, १३.
दवीयः ६. ४७, २९.
दर्श १. ५३, ६; ९; ९५, २; ११६, २४; १२६, ३; १४४, ५; १६४, १४; २. १, ८; १३, ९; ३. २३, ३; २९, १३; ४. ३२, १९; ५. ३३, ८; ४३, ४; ४५, ७; ११; ४७, ४; ६२, १; ७८, ९; ६.

३१, ३; ४७, १८; २२[२]; २३[३]; २४; ६३, ९; ७. ८३, ७; ८. १, ३३; ३, २३; ५, ३७; ३८; ६, ४७; ४६, २२[३]; २३; ५६, २; ९. १, ७; ६, ५; ८, ४; १५, ८; ३८, ३; ४६, ६; ५६, ३; ६१, ७; ६३, ९; ६८, ७; ७१, ५; ८०, ४; ५; ८५, ७; ९१, १; ९२, ४; ९३, १; ९७, १२; १०. २७, १५; ३४, १२; ८५, ४५; ९४, ७[२]; १०१, १०.
दशऽअंगुलं १०. ९०, १.
दशऽअंतरुष्यात् १०. ५१, ३.
दर्शऽअरित्रः २. १८, १.
दर्शऽओणये ६. २०, ४.
दर्शऽओर्णि ६. २०, ८; १०. ९६, १२.
दर्शऽओण्ये ८. ५२, २.
दर्शऽकक्ष्येभ्यः १०. ९४, ७.
दर्शऽग्वः १०. ६२, ६.
दर्शऽग्वं ८. १२, २.
दर्शऽग्वाः २. ३४, १२.
दर्शऽग्वासः ५. २९, १२.
दशुऽग्विनः ८. १, ९.
दर्शऽग्वे ४. ५१, ४.
दर्शऽग्वैः १. ६२, ४; ३. ३९, ५.
दर्शऽतयः १. १५८, ४.
दर्शऽतयस्य १. १२२, १२; १३.
दर्शते १. १८९, ५.
दर्शऽद्युं १. ३३, १४; ६. २६, ४.
दर्शऽप्रमतिं १. १४१, २.
दशऽभिः २. १८, ४; ३. ३९, ५; ४. २४, १०; ५. २७, १; ३४, ५; ७. ८३, ६; १०४, १५; ८. १, ३३; ७२, ८; ९६, १३; ९. २८, ४; ७०, ४; ७२, २; ९७, २३; ५७; १०. ४, ६.
दर्शऽभुजिः १. ५२, ११.
दशमं ८. २४, २३.
दर्शऽमायं ६. २०, ८.
दशऽमास्य ५. ७८, ८.
दर्शऽमास्यः ५. ७८, ७.
दशमे १. ११७, १२; १५८, ६; १०. १८४, ३.
दर्शऽयंत्रं ६. ४४, २४.
दर्शऽयंत्रासः १०. ९४, ८.
दर्शऽयोक्त्रेभ्यः १०. ९४, ७.
दर्शऽयोजनेभ्यः १०. ९४, ७.
दर्शऽरथस्य १. १२६, ४.
दर्शऽव्रजं ८. ८, २०.
दर्शऽव्रजे ८. ४९, १०; ५०, ९.
दर्शऽशाखाभ्यां १०. १३७, ७.
दशऽशिप्रे ८. ५२, २.
दशऽसुं ८. १०१, १३.
दशस्य ६. ११, ६; ८. १६, १२; ४६, ११.
दशस्य ३. ७, १०; ७. २८, ४; ४३, ५.
दशस्यत ५. ५०, ३.
दशस्यतं १. १५८, १.
दशस्यतं १. १३९, ५.
दशस्यति ९. ३, ५.
दशस्यथं ८. २०, २४.
दशस्यथः ८. ५, २३.
दशस्यन् १. ६१, ११; १८१, ८; २. १९, ५; ६. २६, ६; ७. ५, ७; १००, ४; १०. ९९, १०; १३८, १.
दशस्यंतः ५. ३, ४; ६. ५०, ११; ७. ५६, १७.
दशस्यंता ६. ६२, ७; ८. २२, ६; ३१, ९.
दशस्यंतीः ५. ४२, १२.
दशस्यसि ८. ८८, ६.
दशस्या ७. ९९, ३.
दशस्येः ७. ३७, ५.
दशस्येत् १०. १०, ९.
दशानां १०. २७, १६.
दर्शाभीशुऽभ्यः १०. ९४, ७.
दर्शावनिऽभ्यः १०. ९४, ७.
दशो इति ६. ४७, २३.
दसत् १. १२१, १५; १३९, ५.
दर्समानः १. १३४, ५.
दसयंत ५. ४५, ३.
दसाय ६. २१, ११.
दस्म ५. ६, ५; ८. ७४, ७.
दस्म १. ४, ६; ६२, ५; ११; १२; १३८, ४; २. ९, ५; ४. १, ३[२]; ५. ३१, ७; ६. १, १; १८, ५; ७. ३, ४; २२, ८; ८. ९२, १८; १०३, ७; १०. ७, १; ४३, २; १४७, ५.
दस्मः १. १२९, ३; १४८, ४; २. १, ४; ३. ३, २; ७. १८, ११; ९. ८२, १; १०. ९९, १०.
दस्मत् १. ७४, ४.
दस्मऽतमः २. २०, ६.
दस्मं १. ४२, १०; ७७, ३; ५. ३४, १; ७. ३१, ९; ८. ८८, १; १०. ११, ४; ३१, ३.
दस्मऽवर्चसां ८. ९४, ८.
दस्मऽवर्चाः १. १७३, ४; ६. १३, २; ५८, ४.
दस्मस्य १. ६२, ६; ३. १, ७; ५. १७, ४.
दस्मा ४. ४१, ६.
दस्माः ४. ६, ९; ५५, २; ५. ४९, ३.
दस्माः ५. ४१, १३.
दस्मात् ८. ४५, ३५.
दस्मे ३. ५५, १५.
दस्म्यं ८. २४, २०.
दस्यति १०. ११७, १.
दस्यंति १. ११, ३; ६२, १२; १३५, ८[२]; ५. ५४, ७; ५५, ५.
दस्यवः १. ५१, ८.
दस्यवि ८. ६, १४.
दस्यवे १. ३६, १८; १०३, ३; ८. ५१, २; ५६, २; ९. ९२, ५; १०. ४९, ३; १०५, ७.
दस्यवे ८. ५५, १; ५६, १.
दस्युः २. ११, १८; ४. १६, ९; १०. २२, ८.
दस्युऽघ्ना ४. १६, १०.
दस्युंऽजूताय ६. २४, ८.
दस्युऽतर्हणा ९. ४७, २.
दस्युंऽभ्यः ४. २८, १; १०. ४८, २.
दस्युं १. ३३, ४; ७; ९; ५३, ४; ५९, ६; ११७, २१; १७५, ३; २. १५, ९; ५. ४, ६; ३०, ९; ६. १४, ३; ७. १९, ४; ८. ५०, ८; ७०, ११; ९. ४१, २; १०. ७३, ५.

दस्युऽहत्याय १. ५१, ६; १०३, ४; १०. ९५, ७.
दस्युऽहत्ये १०. ९९, ७; १०५, ११.
दस्युऽहत्येषु १. ५१, ५.
दस्युऽहने १०. ४७, ४.
दस्युहन्ऽतमं ६. १६, १५; ८. ३९, ८; १०. १७०, २.
दस्युऽहा १. १००, १२; ६. ४५, २४; ८. ७६, ११; ७७, ३; १०. ८३, ३.
दस्यून् १. ६३, ४; ७८, ४; १००, १८; १०१, ५; २. ११, १९; १३, ९; २०, ८; ३. २९, ९; ३४, ६; ९; ४. १६, १२; २८, ३; ४; ५. ७, १०; १४, ४; २९, १०; ३१, ५; ७; ७०, ३; ६. १८, ३; २३, २; २९, ६; ७. ५, ६; ६, ३; ८. १४, १४; १०. ५५, ८; ८३, ६; ९९, ८.
दस्येत् ६. ३७, ३.
दस्योः १. १०४, ५; ११७, ३; २. १२, १०; ३. ४९, २; ६. ३१, ४; ८. ९८, ६; ९. ८८, ४.
दस्र १. ४२, ५; ६. ५६, ४.
दस्रा १. ३, ३; १५८, १; १८३, ५; ४. ४४, ६; ५. ७५, २; ७. ६९, ३; ८. ५, ११; ८, १; ८७, ५.
दस्रा १. ४६, २; ९२, १८; १८२, २; ६. ६२, ५; ८. २६, ६; ८६, १; १०. २६, १; ४०, १४.
दस्रा १. ३०, १७; ४७, ३; ६; ९२, १६; ११२, २४; ११६, १०; १६; ११७, ५; २०; २१; ११८, ६; ११९, ७; १२०, ४; १३९, ३; ४^{२}; १८०, ५; १८२, ३; ४. ४३, ४; ६. ६९, ७; ७. ६८, १; ८. ५, २; २२, १७.
दस्राः ५. ५५, ५.
दस्रौ १. ११८, ३; १८३, ४.
दस्रौ १. ३०, १८; ११७, २२; ५. ७५, ९.
दह ४. ४, १५.
दह १. १२, ५; ३६, १४; २०; ७९, ६; ७. १, ७; १५, १३; ८. २३, १४; ६०, ७; १०. ८७, १९; २३; २४; १०३, १२; ११८, ७.
दहः १०. १६, १.
दहतात् ३. १८, १.
दहन् ३. २९, ६; ८. ४३, २६.
दहन्ति १०. २८, ८; ३४, ९.
दहन्तु १०. ८७, २०.
दहाति १. ९९, १.
दहामि १. १३३, १.
दाः २. २, ७^{२}; ३. २४, ५; ६. १६, २६; ७. १, ५; १०. ८५, ३८; १४८, ४.
दाः १. १०४, ५; ७; ८; १२१, ४; १६९, ४; १८९, ५; २. ४, ८; ५. २४, १; ३३, ६; ६. १३, ६; १९, ६; २०, ७; २६, १; ३३, १; ३५, १; ७. १, १९; ४६, ४; १००, २; ८. २, १५; ४८, ८; ७१, ७; ९. ९७, २५; १०. ३०, ४; ४७, १; ५९, ४; १२८, ८.
दात् १. १२१, १२; ८. २, ३९.
दात् १. २४, १; २; ५. ३, १२; ६. ६३, ९; १०^{२}; ७. ४५, २; ९७, ४; ८. ३२, १५; ९. ९७, ५२; १०. १७, ७; ८०, ४.
दात २. ३४, ७; ६. ४९, १५; ७. ५६, १५.
दातं ८. ८, १७.
दातवे ४. २०, १०; ७. ५९, ६; ८. १९, २९; ७१, १५; ९. ७५, ५.
दातवै ४. २१, ९.
दाता १. २२, ८; २. २२, ३; ३. १३, ३; ४. १७, ८; ५. ७, ७; ६. २३, ३; ७. २०, २; ८. ६६, २; १०. ५५, ६.
दाता ५. २३, २; ६. २३, १०; २९, १; ३७, ५; ७. ९७, २; ८. ५१, ५; ६५, १०; ९०, २; ९२, ३; ९६, २०; ९. ९७, ५५; १०. ५४, ५.
दातां १०. १४, १२.
दातारः ६. ५०, ११.
दातारं ४. ३१, ७.
दातारं २. ३३, १२; ८. ३, २४; ४६, २^{२}.
दातारौ ६. ६०, १३.
दाति ४. ८, ३; ५. ७, ७; ४८, ५.
दाति १. ६५, ४; ६. २४, २; ७. १५, १२; ४२, ४.
दातिऽवारः १. १६७, ८.
दातिऽवारं ५. ५८, २.
दातिऽवाराः ३. ५१, ९.
दातु १०. ९९, १.
दातु ७. १५, ११; ८. ५२, ५.
दातुः १. १३, ११.
दातु ५. ३६, १; ७९, १०.
दातृन् ६. ५१, ४.
दातोः ७. ४, ६.
दात्रं ८. ७८, १०.
दात्रं १. ११६, ६; १६६, १२; १८५, ३; ३. ५४, १६; ६. २०, ७; ८. ४३, ३३; १०. ६९, ४.
दात्रस्य ८. ४४, १८; ९. ९७, ५५.
दात्रा ४. ३८, १.
दात्राणि ६. ६१, १.
दात्रात् ७. ५६, २१.
दात्रे ६. ४४, १०.
दाधर्थ ७. ९९, २; ३.
दाधार १. ६६, २; ६७, ३; १५४, ४; १५६, ४; ३. ३२, ८; ६. ३०, २; ८. १५, २; ९. ३५, ६; १०. ६०, ९; १११, ४.
दाधार १. ६२, ९; ३. ५९, १; ६. ४४, २४; ४७, ४; ५१, ८; ९. ७४, २; १०. ६०, ८; १२१, १.
दाधृविः ६. ६६, ३.
दानऽअप्नसः १०. २२, ११.
दानऽओकसं १. ६१, ५.
दानः ७. २७, ४; ८. ४, ८; १०. ३२, ९.
दानं १. १२८, ५; ५. ३०, ७; ३३, ६; ७. १८, २२; ८. ४६, ६; ५१, ७; ६१, ६; ९. ५२, ३.
दानं ६. ४५, २३.
दानवं ५. २९, ४; ३२, १.
दानवस्य २. ११, १०; ५. ३२, ४.

दानऽवान् ८. ३२, १२.

दानवार्य ५. ३२, ७.

दाना ५. ५२, १४; १५; ८७, २; ८. २०, १४; ३३, ८.

दानाः ५. २७, ५; ७. १८, २३.

दानाः ८. ६४, ९.

दानाय ६. ५३, ३; १०. १४१, ५; ६.

दानाय १. ४८, ४; ५५, ७; ११२, २; १८०, ५; २. १३, १३; १४, १२; ६. ४५, ३२; ८. ४६, २६; ५१, ६; ५४, ५; ६१, ८; ७०, ८; ७१, ११; ९९, ४; ९. ८१, १; १०. ६१, २; ६२, ८.

दानासः ८. ४६, २४.

दानु ६. ५०, १३.

दानुः १. ३२, ९; ५४, ७.

दानुऽचित्राः १. १७४, ७; ५. ३१, ६; ५९, ८.

दानुऽदः ९. ९७, २३.

दानुनः १. १३६, ३; २. ४१, ६.

दानुनः ८. ८, १६.

दानुना १०. ४३, ७.

दानुऽपिन्वः ९. ९७, २३.

दानु २. ११, १८; १२, ११; ४. ३०, ७.

दानुऽमत् १. ५१, ४.

दानुऽमत्याः ५. ६८, ५.

दानून् १०. १२०, ६.

दानूनि ८. २५, ६.

दाने २. १३, ७.

दान्ति १०. १३१, २.

दां १०. ४९, १.

दाम १. १६२, ८.

दामऽइव २. २८, ६.

दामनः ५. ३६, १.

दामनि १. ५६, ३.

दामने ८. ९३, ८.

दामन्ऽवंतः ५. ७९, ४; ६. २४, ४.

दामा ६. ४४, २; ८. ७२, ६.

दामानः ८. २१, १६.

दामाने ४. ५४, २; ८. २३, २; १०. ४२, ८.

दाम्नः ७. ८६, ५.

दायं १०. ११४, १०.

दायि १. ६१, १५; २. २०, ८; ६. २५, ८.

दारु ६. ३, ४; १०. १०२, ८; १४६, ४; १५५, ३.

दारु ७. ६, १.

दारूणि ८. १०२, २०.

दार्भ्याय ५. ६१, १७.

दावने १. ६१, १०; १२२, ५; १३४, १^{2}; २; १३९, ६; २. १, १०; ११, १; १२; ४. २९, ५; ३२, ९; ५. ३९, २; ५९, १; ४; ६५, ३; ६. ७१, २; ८. ७, २७; २५, २०; ४५, १०; ४६, २५^{2}; २७; ६३, ५; ६९, १७; ७०, १२; ९२, २६; ९. ९३, ४; १०. ३२, ५; ४४, ७; ५०, ७.

दाशत् १. ७०, ३; ४. २, ९; ६. १६, २०; ७. १००, १; ८. १९, १४; १०३, ४; १०. ६१, २५; ९१, ११; १२२, ३; १३८, ५.

दाशत् १. १५८, २; २. १९, ४; १०. ६५, ६.

दाशतः ७. १४, ३; १७, ७.

दाशति १. ९३, १०; १५१, ७; ६. १६, ३१; ६८, ५; ७. ५९, २.

दाशऽराज्ञे ७. ३३, ३; ५; ८३, ८.

दाशसि ८. २४, २.

दाशा १. १२७, ७.

दाशात् १. ६८, ३; ७१, ६; ९३, ३; २. २३, ४.

दाशुऽअध्वरः १. ७५, ३; ८. १९, ९; १०. १४७, ४.

दाशुऽअध्वरं ८. ४, १३.

दाशुऽअध्वराय ६. ६८, ६.

दाशुरिः ८. ४, १२.

दाशुषः १. ३, ७; ११०, २; १४२, २; १७८, ३; २. २०, २; ३. २५, ४; ५१, ९; ६०, ५; ४. ९, ८; ४६, ६; ४९, ६; ५. ७१, ३; ६. ६२, ३; ७. ७४, ४; ८. ५, ५; १३, १०; २२, ३; ८; ८४, ३; ८५, ६; ९. १००, २; ८; १०. १२२, ५.

दाशुषे १. १, ६; २, ३; ८, ८; ९; २५, ६; २७, ६; ३५, ८; ४४, १; ४; ४५, २; ८; ४७, १; ९; ६१, ११; ७४, २; ९; ८१, ६; ८४, ७; ८५, १२; ९१, ९; ९३, १; ९४, १४; ११३, १८; १२४, १२; १३०, ७^{2}; १४२, १; १६३, १३; २. १, ११; १९, ४; ३२, ५; ३. २, ११; २४, ५; ६२, ४; ४. ११, ३; १५, ३; २०, ९; १०; २६, २; ३०, २०; ३४, ४; ४७, ४; ५३, १; ५. ३, १; २५, ५; ३४, ७; ५७, ३; ७६, २; ८०, ६; ८२, ३; ६. १६, ५; २०, ७; २६, ३; ५०, ८; ६१, १; ६५, ३; ४; ६७, ८; ७१, ४; ७. ३, ८; ५, ८; ११, ३; १६, १२; १९, ६; २०, २; २७, ३; ३७, ५; ७०, ३; ७१, २; ८१, ३; ८. १, २२; ५, ६; १२, २१; २१, १७; २४, ९; २२; २७, २०; ३५, २२; ४३, १५; ४७, १; ४९, २; ५०, ३; ६; ५१, ७; ५२, ८; ६६, ४; ६७, ३; ६९, १३; ७१, ६; ८८, ६; ९०, ४; ९३, २१; २६; ९५, ९; १०२, १; ९. ३, ६; ३६, ५; ६२, ११; ६४, ६; ९८, ४; १०. १५, ७; १७, ७; २१, ६; २५, ११; २८, ७; ४८, १; ४; ६५, ५; ६; ११३, ५; १२२, ३; १४०, १.

दाशेम ४. १०, ४; ६. ४८, २; ७. ३, ७; ८. ८४, ५.

दाशेम १. ७६, १; ७७, १; ४. ५, १; ५. ४१, १६; ७. १४, १; २; २९, ३.

दाश्नोति ८. ४, ६.

दाश्वांसः १. ३, ७; ७. ३७, ४.

दाश्वांसं १. ४७, ३; १३६, ५; १८२, २; ४. २, ८; ४६, ५; ७. ९२, ३; ८. ५७, ४; ५९, ३; ७१, ४.

दाश्वान् १. ४०, ७; ७४, ८; १५०, १; ३. ११, ७; १०. १०४, ६.

दाष्टि १. १२७, ४^{2}.

दासः ८. ५१, ९; १०. ३८, ३.

दासः १. १५८, ५; ५. ३०, ९; ७. ८६, ७.
दासत् ८. १, ३३.
दासथः ८. ४०, १.
दासऽपत्नीः १. ३२, ११; ३. १२, ६; ५. ३०, ५; ८. ९६, १८.
दासऽप्रवर्गं १. ९२, ८.
दासं २. १२, ४; ३. ३४, १; ५. ३४, ६; ६. २६, ५; ७. १९, २; १०. ४९, ६; ७; ५४, १; ७३, ७; ८३, १; ८६, १९; ९९, ६.
दासं २. ११, २; ४. ३०, १४; ८. ३२, २; ७०, १०.
दासऽवेशाय २. १३, ८.
दासस्य १. १०४, २; ७. ९९, ४; १०. २३, २; १०२, ३.
दासस्य २. २०, ६; ४. १८, ९; ३०, १५; ५. ३०, ७; ८; ३३, ४; ६. २०, ६; ८. २४, २७; ४०, ६; १०. २२, ८.
दासा ६. ३३, ३; ७. ८३, १.
दासा ६. ४७, २१; १०. ६२, १०.
दासाः १. १५८, ५.
दासान् ८. ५६, ३.
दासानां ४. ३०, २१.
दासानि ६. २२, १०; ६०, ६.
दासाय १. १७४, ७; १०. १२०, २; १३८, ३.
दासीः १. १०३, ३; २. ११, ४; २०, ७; ४. २८, ४; ३२, १०; ६. २०, १०; २५, २; ८. ५, ३१.
दासीत् ७. १, २१.
दासे ८. ४६, ३२.
दास्वतः ५. ९, २.
दास्वंती १. ४८, १.
दास्वंते २. ४, ३; १०. १४४, २.
दास्वंतं १. १२७, १.
दास्वान् ४. २, ७; ६. ३३, १; ६८, ५.
दितिः ७. १५, १२.
दितिं ४. २, ११; ५. ६२, ८.
दित्संतं २. १४, १०; ७. ३२, ५; ८. ८१, ३; ९. ६१, २७.
दित्ससि ४. ३२, ८; ८. १४, ४; ८८, ३.
दित्ससि १. १७०, ३; ४. ३२, २०.
दित्सु ५. ३९, ३.
दित्सेयं ८. १४, २.
दिदासतः १०. १५१, २.
दिदिड्ढि २. ३२, ६; ४१, १७.
दिदिष्ट १०. ९३, १५[३].
दिदिष्टन १०. ९२, ९; १३२, ६.
दिदीपः ८. ४८, ६.
दिदीहि ९. १०८, ९.
दिदीहि १. ११३, १७; २. ९, ६; ३. ३, ७; १५, ४; २३, ४; ५४, २२; ५. ४, २; २५, ३; ७. १, २१; ३, १०.
दिदृक्षंते ३. ३०, १३.
दिदृक्षुं ७. ८६, ३.
दिदृक्षेण्यः १. १४६, ५.
दिदृक्षेण्यं ५. ५५, ४.
दिदृक्षेयः ३. १, १२.
दिदेष्टु ७. ४०, २.
दिद्यवः ४. ४१, ११; ६. ४६, ११; ७. ८५, २; १०. ३८, १, १३४, ५.
दिद्युत् १. ६६, ४; १६६, ६; ५. ८६, ३; ६. ६६, १०; ७. २५, १; ३४, १३; ४६, ३; ५७, ४.
दिद्युतः २. १३, ७; ८. ६, ७; १०. १५८, २.
दिद्युतः २. २, ७; ५. ३०, ४.
दिद्युतानः ३. ७, ४.
दिद्युते ९. ८०, १.
दिद्युं १. ७१, ५; ४. ४१, ४; ६. ४६, ९; ७. ५६, ९; १०. ४८, ९; १४२, १.
दिधिषंत १. १३२, ५.
दिधिषंति २. ३५, ५.
दिधिषंतु ३. ८, ६.
दिधिषंते १०. ६३, १.
दिधिषंते ४. १८, ७.
दिधिषवः १०. ७८, ५.
दिधिषाणाः १०. ११४, १.
दिधिषामहे १०. १३२, ३.
दिधिषामि २. ३५, १२.
दिधिषाय्यः १. ७३, २; २. ४, १.
दिधिषुं ६. ५५, ५.
दिधिषेम ८. ९६, ६.
दिधिषेय ७. ३२, १८.
दिधिषोः १०. १८, ८.
दिधिष्वः १. ७१, ३.
दिधृत १. १३९, ८.
दिधृतं ५. ८६, ६[२].
दिनस्य ८. ७८, १०.
दिप्संति २. २८, १०; ७. १०४, १०; ११.
दिप्संतः १. १४७, ३; २. २७, ३.
दिप्संति १. २५, १४.
दिप्संति ७. १०४, २०.
दिप्सवः १. २५, १४; ७. १०४, २०.
दियानां ८. १९, ३७.
दिवः १. ११७, १२; २. ३, २; ३. ३८, ५; ४. ४४, २; ५३, ५; ९. १०८, ११.
दिवः १. ६, ९; १०; १८, ९; २३, १३; २५, २०; ३१, १५; ३३, ५; ७; १०; ३४, ८; ३७, ६; ३८, २; ४६, १; ८; ९; ११; ४७, ६; ४८, ८; १५; ४९, १; ३; ५२, ९; ५४, ४; ७; ५५, १; ५६, ५; ६; ५८, २; ५९, २; ५; ६०, २; ६१, ९; ६२, ५; ६४, २; ४; ६९, १; ७१, २; ७२, ८; १०; ८०, ४; ८६, १; ९२, ५; ७; ११; १७; ९३, ६; १००, १; ३; १३; १५; १०५, ३; ५; १०; ११; १०८, १२; १०९, ६; ११०, ६; ११३, ७; १४; ११४, ५; ११५, ३; १२१, ८–१०; १२२, १; १२४, ३; १३०, ३; १३४, ४; १४२, ३; १४६, १; १५१, ४; १५५, ३; १६४, १०; १२; १६६, ५; १६८, ४; १८१, ४; १८२, १; १८३, २; १८४, १; २. १, ६; ६, ५; १३, ७; २७, १५; ३०, ५; ३१, ३; ३८, ११; ४०, १; ३. १, २; ३; ६; ९; २, १२; १४[२]; ४, ४; ५, ९; ६, २; ७; ८; १२, ९; १७, २; २२, ३; २५, १; ३१, ८; ३९, २; ४३, ६; ४६, ३; ४९, ४; ५३, ७; ८;

५४, ११; १३; ५६, ५; ६; ५७, २; ६१, ४; ६; **४.** २, १५; ३, ८; ७, ८; ८, २; ४; १०, ४; १३, ५; १४, ५; १५, ६; १६, ३; २१, ३; २६, ६; ३०, ८; ९; ३९, १; ४३, ३; ४४, ५; ४५, १; ५१, १; ५२, १; ५३, २; ५४, ४; **५.** १०, ४; १५, २; १७, ३; २५, ८; ३८, ३; ४०, ६; ४१, १; ३; ४; ७; ४३, ११; ४५, १; ४७, १; ३; ४; ६; ५२, ५–७; १४; ५३, ६; ८; ५४, १; १३; ५७, १; ५; ५९, ६; ७; ६०, ३; ७; ६३, १; ३; ५; ७४, १; ८०, ५; ६; ८३, ६; ८४, ३; ८७, ३; **६.** १, ७; २, ३; ४; ११; ३, ७; ७, १; ६; ७; १३, १; १५, १; १६, ९; १८, १२; २०, २; ३०, १; ४४, २१; ४७, ४; २७; ४९, २; ५१, १; ४; ५२, १५; ५८, ४; ६२, १; ६६, ११; ७१, ५; **७.** ३, ६; ५, १; ६, ७; १५, ४; २४, ३; ३४, २; ३६, ३; ३८, ५; ३९, ५; ४५, २; ४६, ३; ६०, ७; ६१, ३; ६३, ४; ६४, २; ६६, १४; १८; ६७, २; ६९, ३; ७०, ३; ७५, ४; ७८, ४; ७९, २; ३; ८१, १; ९७, १; १०२, १; १०४, ४; १९; **८.** १, १८; २९; ५, ८; ७, ७; ११; १३; ८, ४; ७; १०, १; १२, ६; १३, ८; १३; १४, ९; २०, १७; २५, ७; १८; १९; २६, १७; २३; २७, १९; ३४, १; ३६, ४; ४०, ८; ४४, १६; ५७, ३; ६०, १९; ६३, २; ६५, २; ६९, ३; ७२, ८; ७९, ४; ८२, ४; ८७, ४; ८८, ५; ९४, ९; १०; ९७, ५; ९८, ३–६; **९.** २, ५; ८, ८; ९, १; १०, ९; १२, ४; ८; १६, ७; २६, २; २७, ३; ३१, २; ३३, ५; ३६, ६; ३७, ३; ३८, ५; ३९, २; ४; ४२, १; ४८, १; ३; ४९, १; ५१, २; ५७, १; ४; ६१, १६; ६२, २८; ६३, २७; ६४, ८; ३०; ६५, २४; ६६, ५; ३०; ६८, ८; ९; ६९, ५; ८; ७१, ७; ७२, ७; ७३, ४; ५; ७४, १; २; ६; ७; ७५, २; ७६, १; ७७, २; ५; ८०, १; ८३, $२^{२}$; ८५, $९^{२}$; १०; ८६, ३; ८; ९; ११; १९; २४; २७; ३३; ३५; ४६; ८७, २; ८; ८९, १; ३; ६; ९६, ५; १४; ९७, २९; ३०; १०२, ८; १०८, १०; १६; १०९, ६; ११०, $८^{२}$; ११३, ८; ९; **१०.** ३, २; ७, १; ८, १; १०, २; ११, १; १५, १४; १७, ६; २०, ४; २२, ६; २८, ६; ३७, १; ३९, १२; ४५, १; ३; ४९, २; ५५, ८; ५९, ९; ६१, ४; ६२, ६; ६३, ४; ६५, १३; ६६, १०; ७०, ५; ६; ११; ७६, ५; ७७, २; ३; ८९, ३; १०; १२; ९२, ६; ९; ९७, १७; ९८, ३; १०; १२; १०८, ५; १११, ३; ५; ७; ११४, १; १३८, ३; १३९, २; १४३, ३; १४९, ४; १५८, १; १७०, २.

दिवः **१.** ३०, २२; ४८, १; ९; ४९, २; **२.** ३६, २; **४.** ५१, १०; ११; **५.** ५४, १०; ७९, २; ३; ८; ९; **६.** ६४, ४; ५; ६५, ६; **७.** ७७, ६; ८१, ३; ५; **८.** ४७, १४; १५; **१०.** १२७, ८.

दिवःऽइव **२.** २, २; **१०.** ६२, ९.

दिवःऽजाः **६.** ६५, १.

दिवःऽदासं **१.** ११२, १४; **४.** २६, ३; **६.** २६, ५; ६१, १; **७.** १८, २५.

दिवःऽदासस्य **६.** १६, ९.

दिवःऽदासात् **६.** ४७, २२; २३.

दिवःऽदासाय **१.** ११६, १८; ११९, ४; १३०, ७; **२.** १९, ६; **४.** ३०, २०; **६.** १६, ५; ३१, ४; ४३, १; **९.** ६१, २.

दिवःऽदासेभिः **१.** १३०, १०.

दिवःऽपृथिव्योः **२.** २, ३; **५.** ४९, ५; **१०.** ३, ७; ३५, २.

दिवःऽरुचः **३.** ७, ५.

दिवक्षसः **३.** ७, २; **१०.** ६५, ७.

दिवक्षाः **३.** ३०, २१.

दिवं **१.** ५०, ११; ५२, १२; ६२, ८; ६८, १; १६४, ४७; ५१; **३.** ५९, ७; **४.** ४२, ४; **६.** २१, २; **८.** ६, ४८; ३४, १; ५१, ८; ५५, २; १००, ८; **९.** ३, ७; ८; १७, ५; ५४, २; **१०.** ५६, ३; ५८, २; १२१, ९; १८९, २; १९०, ३.

दिवा **१.** २४, १०; १२; ३४, २; ३८, ९; ९८, २; १३९, ५; १४४, ४; **५.** ७६, २; ३; **६.** ३, $६^{२}$; ४९, १०; **७.** १५, १५; ७१, १; २; १०४, ११; **८.** ७, ६; १८, ६; ७; २५, ११; ६१, १७; ६४, ६; **९.** ९७, ९; १०७, २०; **१०.** ९५, ४.

दिवा **१.** १६१, १४; १६३, ६; **३.** ६२, २; **६.** ५२, १; **७.** ६२, १; **८.** ६, ३०; ३५, २; **१०.** १०, ९; ८२, ५.

दिवाऽन्तरात् **१.** १२७, $५^{२}$.

दिवावसो इति दिवाऽवसो **८.** ३४, १.

दिवि **१.** ६, १; ७, ३; १९, ६; ३६, ३; ५१, ४; १२; ५२, ४; ८; ७३, ७; ८०, १३; ८१, ५; ८३, ६; ८५, २; ९१, ४; १८; ९३, ५; ९५, ३; ९८, २; १०३, १; १०५, १; १६; १०८, ११; १२५, ६; १२६, २; १३९, ११; १५०, ३; १५९, ४; १६३, ३; ४; १६४, २५; १८७, ४; १९०, ४; **२.** २२, ४; ४०, ४; **३.** २, १३; १३, ४; २२, २; ६१, ५; **४.** ५, ११; १३, २; ३५, ८; ५७, ५; **५.** २, १०; ९, ५; ११, ३; २७, ६; २८, १; ३५, $८^{२}$; ४०, ८; ५२, ३; ६०, ६; ६१, १२; ६२, ७; ६३, ४; ७; ७४, २; ८५, २; **६.** २, ६; १६, ३६; १७, १४; २३, २; ३३, ५; ३४, ४; ४०, ५; ४४, २३; ४८, ६; **७.** ५, २; ११, ५; ३२, १४; २१; ६४, १; ८२, ३; ८३, ३; ५; ८७, ५; **८.** ३, २१; ९, २; १२,

३०; १३, २९; १४, ५; १९, ४; १८; २२, ६; २९, ९; ५०, ७; ५२, ७; ५५, २; ५६, ५; ६४, ४; ७२, १५; ७४, ३; ८७, १; ८९, ७; ९. १, ७; ४१, ३; ६१, १०; ७९, ४; ८३, २२; १०७, ७; १०. ७, ३; ६; ८, ६; २८, १२; ३५, १०; ६१, १८; ६२, ३; ६४, ३; ६५, ११; ७५, ३; ८०, ४; ८५, १; ११; ८८, १०; ११; ९०, ३; ९६, ४; ९८, ११; १०७, २; ११९, ११; १२४, ७; १५६, ४.

दिविऽईव १. २२, २०; ५. १, १२; ७. २४, ५; १०. ५६, २; ६०, ४; ५.

दिविऽक्षयं ५. ४६, ५.

दिविऽक्षितां १०. ९२, १२.

दिविऽजाः ७. ७५, १; ८. ४३, २८.

दिवितां १०. ७६, ६.

दिवित्मंता १. २६, २; १०. ७६, ६.

दिवित्मंती ५. ७९, १.

दिवित्मंते ४. २१, ११.

दिविऽयजः ९. ९७, २६.

दिविऽयोंनिः १०. ८८, ७.

दिविंष्टयः ७. ७४, १.

दिविंष्टिषु १. ४५, ७; ४८, ९; ८६, ४; १३९, ४[2]; १४१, ६; ४. ९, ३; ४६, १; ४७, १; ८. ४, १९; ७६, ९; ८७, ३.

दिविऽस्पृक् १०. १६८, १.

दिविऽस्पृशः ५. १३, २; ७. १६, ३.

दिविऽस्पृशं १. १४२, ८; २. ४१, २०; ४. ४६, ४; ८. ५, २८; १०१, ९; ९. ८६, १४; १०. ३६, ६.

दिविऽस्पृशां १. २२, २; २३, २; ५. ११, १.

दिविऽस्पृशा १. १३७, १.

दिविऽस्पृशिं १०. ८८, १.

दिविऽस्पृशें ९. ११, ४.

दिवे १. ५४, ३; ७१, ५; १२९, ३; १३६, ६; १८५, १०; २. १३, ५; २४, १४; ३. ५४, २; ३; ४. ३, ५; ५. ४७, ७; ५९, १; ६. १८, १४; ८. ७०, २; ९. १०९, ५.

दिवेऽदिंवे १. १, ३; ७; ३१, ७; ३४, ७; ८९, १; १२३, ४; १३६, ३[2]; २. ९, ५; ३०, २, ११; ३४, ७; ३. ४, २; २९, २; १४; ३०, १२; ३५, ३; ५१, १; ५२, ८; ५६, ६; ४. ८, ७; १५, ६; ५४, ६; ५. २०, ४; ४९, १; ६. १५, २; ३०, २; ३२, ५; ४७, २१; ७१, ६; ७. ३२, १९; ९८, २; ८. ४, १०; १२, २८; १५, ६; ३१, ४; ४५, १२; ५३, २; ९८, ८; ९. १, ५; ६१, २०; ७५, ४; १०१, ६; १०७, १९; १०. ३७, ७; ८७, २२; ९२, ८.

दिव्यः १. १६४, ४६; ५. ४१, ४; ७. ३२, २३; ३७, ८; ९. ७१, ९; ९७, २३; ३३; १०९, ३; १०. ६३, १७; ११६, ३; १३९, ५.

दिव्यं १. १३९, १; १६३, १०; १६४, ५२; १७३, १; ३. १९, ४; ४७, ५; ५. ५९, ८; ६. ६, १; १०, १; ५१, १२; ७. २, १; ९. १९, १; २९, ६; ८६, ३६; १०७, ५; १०. १२, ३; ९६, २; १००, ११.

दिव्यस्यं १. ११२, ३; १४४, ६; २. १४, ११; ५. ६८, ३; ६. २२, ९; ३९, १; ७. ४६, २; ६५, ४; ९७, १०; ९. ८६, २८; ९१, २.

दिव्या १. १४३, ५; १५२, ७; २. २७, ९; ४. ४३, ३; ५. २९, १; ६९, ४; ९. ८८, ७; ९७, ५१; १००, ३; १०७, २४.

दिव्याऽईव १. १६६, ११; १७६, ३.

दिव्याः २. २५, ४; ६. ६, ३; ५०, ११; ७. ३५, ११; १४; ४९, २; १०३, २; ८. ५, २१; २५, ६; ९. ८६, १; ४; ८८, ६; ११०, ६; १०. ३४, ९; ९८, ५.

दिव्यात् ७. १०४, २३.

दिव्यानां १०. १२४, ९.

दिव्यानिं १. ३४, ६; ६४, ३; ५; ४. ५३, ३; ६. २२, ८; ५९, ९; ९. १४, ८; ३६, ५; ६३, ३०; ६४, ६; १०. १३, १; ३२, २; ६४, १६.

दिव्यां ९. ९७, १७.

दिव्यायं १. ५८, ६; १०. ७६, ८.

दिव्यासंः १. ११८, ४; १६३, १०; १८१, २; १०. ६५, ९.

दिव्ये इतिं ७. २, ६; १०. ११०, ६.

दिव्येनं ३. २, ४; १०. ४३, ७.

दिव्येषुं ९. ८६, २२.

दिव्यैः ३. ५४, १.

दिशः १. ३१, १४; ११९, २; १२४, ३; ३. ३०, १२; ६. ६०, २; ९. ७०, ९; ११४, ३; १०. ६४, २; ९०, १४.

दिशंतां १०. ११०, ७.

दिशं १. ९५, ३; १८३, ५; ४. २९, ३.

दिशमानः ३. ३१, २१.

दिशा १. ८५, ११; १३२, ४.

दिशां ९. ११३, २.

दिषीय २. ३३, ५.

दिष्टां १. १८३, ५.

दिहानः १०. ८७, ४.

दीद्यः १०. ६९, ७.

दीदंयत् १०. ३०, ४; ९५, १२.

दीदयंत् २. २३, १५; ६. १६, ३६; २०, १३; १०. ९९, ११.

दीदयत् २. ४, ३; ५. ४५, ९; ८. ४४, १५.

दीदयतं १. ९३, १०.

दीदयंति ५. ६, ४.

दीदयंसि ८. ४४, २९.

दीदायं २. ३५, ४; ७. ३, ५; १२, १; ८. १०२, ११.

दीदाय ४. ६, ७.

दीदियुः १. ३६, ११.

दीदियुषंः ८. २३, ४.

दीदिंऽवः ७. १, ८.

दीदिऽवः १. १२, ५; १०; ५. २४, ४; ८. ४४, ४; ६०, ५.

दीदिऽवांसं २. २, ११; ३५, ३; १४; ३. १३, ५; २७, १२; ४. ४, ९; ३९, २; ५. ४३, १२; ६. १, २; ६; १०. ८८, १४.

दीदिऽवांसा १०. १०६, ३.
दीदिऽवान् २. ९, १.
दीदिविं १. १, ८.
दीदिहि ८. ६०, ६.
दीदिहि १. ७९, ५; १४०, १०; २. २, ६; ३. १०, २; ८; ५४, २२; ५. २१, ४; २३, ४^{2}; ६. ४८, ३; ७^{2}; ७. १, ३; १५, ८; ८. ४३, २६; १०. ११८, ७.
दीदेत् २. २, ८.
दीदेथ १. ३६, १९; ४४, १०.
दीद्यग्नी इति दीदिऽअग्नी १. १५, ११; ८. ५७, २.
दीद्यत् १. १४३, ७; २. ९, २; ३. १, १; ७. १०, १; १०. ११८, १; ८; १२२, ६.
दीद्यतं ३. २७, १५.
दीद्यानः १. १२७, ३; ३. ५, ७; १५, ५; ३१, १५; ६. १, ७; १०. २०, ४.
दीद्यानं ४. ५, ९.
दीद्ये ३. ५५, ३.
दीधय ३. ३८, १; १०. २२, ४.
दीधयुः ८. २१, ६.
दीधयन् ७. ७, ६.
दीधरः ८. १००, १.
दीधरत् ३. २, १०; ८. ६८, १९.
दीधरं ९. १०५, ४.
दीधरिति दीधः ६. १७, ६; ६७, ४.
दीधितिः १. १८६, ११; ३. ४, ३; ५. १८, ४.
दीधितिऽभिः ७. १, १.
दीधितिं ३. ३१, १; ४. २, १६; ९. १०२, १; ८.
दीधिती ५. ४२, १.
दीधिम ८. ९९, ३.
दीधियुः १०. ४०, १०.
दीधेत् १०. १४४, ३.
दीध्यतः २. २०, १.
दीध्यानः १. १६३, १२; ४. २३, ४; १०. १०, १.
दीध्यानाः ३. ४, ७; ४. ३३, ९; ५०, १; ७. ९०, ४; ५; ९१, ४; १०. ६७, २; १८१, ३.
दीध्यानां १०. १८३, २.
दीध्ये ५. ३३, १.
दीनतां ७. ८९, ३.
दीनऽदक्षाः १०. २, ५.
दीनाः ४. २४, ९.
दीने ८. ६७, ११; १०. ६८, ८.
दीनैः ४. ५४, ३.
दीपयः ६. २२, ८.
दीय ५. ८३, ७; १०. १०३, ४.
दीयत् १. १८०, १.
दीयतं ५. ७४, ९.
दीयति ९. ३, १.
दीयथः ५. ७३, ३.
दीयन् ६. ४, ६; ७. ६३, ५.
दीयंति ७. ७४, ४.
दीयंति २. ३५, १४.
दीर्घऽअप्साः १. १२२, १५.
दीर्घऽआयुः ४. १५, ९; १०. ८५, ३९.
दीर्घऽआयुषं ४. १५, १०.
दीर्घः १. १७३, ११; ४. २, ५; ८. १७, १०.
दीर्घऽजिह्व्यं ९. १०१, १.
दीर्घऽतंतुः १०. ६९, ७.
दीर्घऽतमाः १. १५८, ६; ८. ९, १०.
दीर्घऽधियः २. २७, ४.
दीर्घऽनीथे ८. ५०, १०.
दीर्घऽप्रयज्युं ७. ८२, १.
दीर्घऽप्रसद्मनि ८. १०, १; २५, २०.
दीर्घं १. ३२, १०; ३७, ११; ९६, ८; ११६, २५; १२२, ८; १५४, ३; १६६, १२; १४; ३. ७, १; ४. २३, ९; २४, ८; ५. ५४, ५; ८७, ७; १०. १४, १४; १८, ६; ३६, १४; ५१, ८; ७०, ४; ८५, १९; ९५, १०; १०५, १; १२४, १; १३४, ६.
दीर्घऽयशसे ५. ६१, ९.
दीर्घऽयाथे ५. ४५, ९.
दीर्घऽयाथैः २. १५, ३.
दीर्घऽश्रवसः १०. २३, ३.
दीर्घऽश्रवसे १. ११२, ११.
दीर्घऽश्रुत् ७. १६, ८; ६१, २; ८. २५, १७.
दीर्घऽश्रुतः १०. ११४, २.
दीर्घऽश्रुतं ७. ७६, ७.
दीर्घश्रुत्ऽतमः ८. १०२, ११; १०. ९३, २.
दीर्घश्रुत्ऽतमं ५. ३८, २; ७. ८१, ५.
दीर्घश्रुत्ऽतमा ५. ६५, २; ८. १०१, २.
दीर्घा १. १४०, १३.
दीर्घाः २. २७, १४.
दीर्घां ४. २२, ७; १०. ४०, १०.
दीर्घाय १. ७, ३; ८. १३, ३०.
दीर्घायुऽत्वं १०. ६२, २.
दीर्घायुऽत्वाय ८. ५९, ७.
दीर्घायुऽशोचिषं ५. १८, ३.
दीर्घायो इति दीर्घऽआयो ८. ७०, ७.
दीर्घेण १. ११९, ६.
दीवि ५. ८५, ८.
दीवे १०. २७, १७.
दीव्यः १०. ३४, १३.
दुः १. १२७, ४; १०. १६१, ४.
दुः ५. ४९, ५; ८. ३, २१.
दुःऽआधर्षं ६. ४९, ७; १०. १८५, १.
दुःऽआध्यः ७. १८, ८; ३२, २७; ९. ७९, ३.
दुःऽआध्यं ६. ५१, १३.
दुःऽआध्ये ८. ७१, ७.
दुःऽआपना १०. ९५, २.
दुःऽआव्यं ९. ४१, २.
दुःऽआशीः ८. २, ५.
दुःऽइतं १. १२५, ७.
दुःऽइतं १. २३, २२; २. २३, ५; १०. ३९, ११; १२६, १.
दुःऽइतस्य ३. ३९, ८; १०. १६१, ३.
दुःऽइता १. ३५, ३; ४१, ३; ९९, १; ३. २०, ४; ५. ३, ११; ४, ९; ९, ६; ६. २, ११; १८, १०; ४७, ३०; ५१, १०; ६८, ८; ७. ३२, १५; ४४, ३; ६५, ३; ७८, २; ८. १८, १७; ४२, ३; ९७, १५; ९. ५९, ३; ६२, २; ७०, ९; ८२, २; ९०, ६; १०. ३१, १; ६३, १३; ९३, ६; ९६, ८; ११३, १०; १२६, ६; १३३, ६.
दुःऽइतात् १. १२१, १४; १२८, ५; १४७, ३; १८५, १०; ३. ३९,

७; ६. ५०, १०; ७५, १०; ७. १२, २.
दुःऽइतानि २. २७, ५; ४. ३९, १; ५. ७७, ३; ८२, ५; ७. १२, २; ८२, ७; ९. ९७, १६; १०. १६५, ५.
दुःऽइताय १. १४७, ५.
दुःऽइतेभ्यः ८. ४४, ३०.
दुःऽउक्ताय १. ४१, ९.
दुःऽउक्तैः १. १४७, ४.
दुःऽएवः ४. ४१, ४; ६. १६, ३१.
दुःऽएवस्य २. २३, १२.
दुःऽएवाः २. २३, ८; ३. ३०, १५; ४. ५, ५; ५. २, ९; १०. ८७, १८; ८९, ९; १२०, ४.
दुःऽएवा १०. ४२, १०.
दुःऽएवायाः १०. ६३, ११.
दुःऽएवासः ७. ६८, ७.
दुःऽएवैः १. ११७, ४.
दुःऽओकं ७. ४, ३.
दुःऽकृतः ५. ८३, २; ९; ७. १०४, ३; ९. ७३, ६.
दुःऽकृते ६. १६, ३२.
दुःऽकृतं ८. ४७, १३; १०. १००, ७.
दुःऽकृतानि १०. १६४, ३.
दुःऽकृतैः ७. १०४, ७; १०. ८६, ५.
दुःऽगं १०. ८५, ३२.
दुःऽगहस्य ८. ६५, १२.
दुःऽगहा ४. १८, २; ५. ४, ९; ८. ४३, ३०; १०. ९८, १२; १८२, १.
दुःऽगहानि ६. २२, ७; ९. ११०, १२.
दुःऽगा १. ४१, ३; ७. ६०, १२.
दुःऽगात् १. १०६, १–६.
दुःऽगानि १. ९९, १; १८९, २; ५. ५४, ४; ८. ४७, ५; १०. ५६, ७.
दुःऽगृभिः १. १४०, ६.
दुःऽगृभिश्वनः १. ५२, ६.
दुःऽगृभीयसे ५. ९, ४.
दुःऽगे ४. २८, ३; ५. ३४, ७; ७. २५, २; ८. २७, १८; ९३, १०.
दुःऽगेषु ६. २१, १२.
दुःऽच्यवनः १०. १०३, ७.
दुःऽच्यवनेन १०. १०३, २.
दुःऽदभ २. २८, ८; ७. ८६, ४.
दुःऽदभः ३. २, २; ४. ९, २; ८.
दुःऽदभं १. १५, ६.
दुःऽदभासः ३. ५६, ८; ७. ६०, ६.
दुःऽदर्शीकं ७. ५०, १.
दुःऽधरं १. ५७, १.
दुःऽधरीतुं १०. २०, २.
दुःधर्तवः ५. ८७, ९.
दुःऽधां १०. १०९, ४.
दुःऽधितात् १. १४०, ११.
दुःऽधुरः ५. ५६, ४.
दुःऽध्यः १. ९४, ८; ९; १०५, ६; ३. १६, २; ७. ८२, १; ८. १९, १५; २१, १२; ७५, ९; १०. ४४, ७.
दुःऽध्या ९. ५३, ३.
दुःऽध्यै १. १९०, ५.
दुःऽनशः ७. ३२, ७; ९. ६३, ११.
दुःऽनशं १. १७६, ४; ६. ४५, २६; ७. १८, २५.
दुःऽनशा ३. ५६, ८; ६. २७, ८.
दुःऽनामा १०. १६२, १.
दुःऽनियंतवः १. १३५, ९^{2}.
दुःऽनियंतुः १. १९०, ६.
दुःऽपदा १. ५३, ९.
दुःऽपरिहंतु २. २७, ६.
दुःप्रऽअव्यः ४. २५, ६.
दुःऽभृतये ७. १, २२.
दुःऽमतयः ७. १, २२.
दुःऽमतिः १. १३१, ७^{2}; २. २३, १४; ३. १५, ६; ७. ५६, ९; ८. ६७, १५; १०. १३४, ५.
दुःऽमतिं १. १२९, ६; ४. ११, ६; ८. १८, १०; १०. ४०, १३; १७५, २; १८२, १.
दुःऽमतीः ८. ७९, ९; ९. ७०, ५.
दुःऽमतीनां १. १२९, ८^{2}; ११^{2}; ८. ४६, १९.
दुःऽमतौ ५. ४२, १६.
दुःऽमदः १. ३२, ६.
दुःऽमदासः ८. २, १२.
दुःऽमंतु १०. १२, ६.
दुःऽमन्मा ८. ६०, ७.
दुःऽमन्मानं १. १२९, ७.
दुःऽमर्षं ८. ४५, १८; ९. ९७, ८; १०. ४५, ८.
दुःऽमायवः ३. ३०, १५.
दुःऽमित्रः १०. १०५, ११.
दुःऽमित्रासः ७. १८, १५; २८, ४.
दुःऽयुजः १०. ४४, ७.
दुःऽवर्तुः ४. ३८, ८; ६. ६, ५.
दुःऽवाससे ७. १, १९.
दुःऽविदत्रस्य १०. ३५, ४.
दुःऽविदत्रा १०. ३६, २.
दुःऽविदत्रा १०. ६३, १२.
दुःऽविद्वांसं ७. ९४, १२.
दुःऽशंसः १. २३, ९; २. २३, १०; ४१, ८; १०. २५, ७.
दुःऽशंसं ७. ९४, १२; ८. १८, १४.
दुःऽशंसान् १. ९४, ९.
दुःऽशासुः १०. ३३, १.
दुःऽशीमे १०. ९३, १४.
दुःऽशेवः १. ४२, २.
दुःऽसहासः ९. ९१, ५.
दुःऽस्तुतिः १. ५३, १.
दुःऽस्तुती २. ३३, ४.
दुःऽस्तुती ७. ३२, २१.
दुःऽस्वप्न्यं ५. ८२, ४; ८. ४७, १४–१७; १०. ३६, ४; ३७, ४.
दुःऽस्वप्न्यात् ८. ४७, १८.
दुःऽहना १. ३८, ६.
दुःऽहनायतः १०. १३४, २.
दुःऽहनायाः १. १२१, १४.
दुःऽहनायुवं ४. ३०, ८.
दुःऽहनावान् ८. २, २०; १८, १४.
दुःऽहितः ८. १९, २६.
दुःऽहृणायुः ७. ५९, ८.
दुःऽहृणायून् १. ८४, १६.
दुक्षः ७. ४, ७.
दुघः ३. ३६, ६.
दुघं ५. १९, ४; ३६, १; ८५, ४; ६. ४८, २२; ७. ७४, ३; ९८, १; ९. ९६, १५; १०. ९४, ९.
दुघाभिः ९. १०७, ९.
दुघा १. १५८, ४.
दुघाःऽइव ८. ५०, ३.

दुर्घानाः १. १००, ३; ३. ३१, १०.
दुर्घानां १०. ६७, ६.
दुच्छुनऽयतें १०. ३७, १२.
दुच्छुनऽस्यसे ७. ५५, ३.
दुच्छुना २. २३, ६; ८. २०, ४; ७५, १३.
दुच्छुनाः १. ११६, २१; ५. ४५, ५; ६. १२, ६; ४७, ३०.
दुच्छुनाभ्यः २. ३२, २.
दुच्छुना ९. ६६, १९; १०. १७५, २.
दुच्छुनायै १. १८९, ५.
दुदुहानः ९. ८६, २१; ९६, १०.
दुदुहुः ९. ७९, ४.
दुदुहे ३. ५७, १.
दुदुहे ३. ३१, ११; ४. ३, १०; ५. ४३, ४; ६. ६६, १; ७. ९५, २; ८. १००, १०; १०. ११, १.
दुदुह्रे ८. ७, १०; ६९, ६; ९. ३१, ५.
दुदुह्रे ३. ५७, २; ५. ६२, २; ९. ५४, १; ७०, १.
दुदोहिथ २. १३, ६.
दुद्रवत् ५. ५०, ४.
दुद्रवत् ७. १६, २.
दुध्रये ६. ३६, २.
दुधितं ४. १, १७.
दुधिता २. १७, ४; ४. १६, ४.
दुधुक्षन् ७. १८, ४; १०. ७४, ४.
दुधुक्षन् १०. ६१, १०.
दुधुवीत ८. ७०, ११.
दुध्रेः १०. १०२, ६.
दुध्र ६. २२, ४.
दुध्रः १. ५६, ३; २. १२, १५; ५. ५६, ३.
दुध्रऽकृतः १. ६४, ११.
दुध्रऽवाचः ७. २१, २.
दुध्राः ८. ६६, २.
दुंदुभिः १. २८, ५; ६. ४७, ३१.
दुंदुभे ६. ४७, २९; ३०.
दुरः १. ६८, ५; ६९, ५; ७२, ८; ११३, ४; १२०, २; १२१, ४; १८८, ५; २. २४, ५; ३. ३१, २१; ४. ४, ६; ५. ४५, १; ६. १७, ६; १८, ५; ३०, ५; ३५, ५; ६२, ११; ७. २, ५; ९, २; ४६, २; ७९, ४; ९. ४५, ३; ६४, ३; १०. २९, ३; १३९, ६.
दुरः १. ५३, २[३]; २. २, ७.
दुरल्येतु इति दुःअल्येतु ७. ६५, ३.
दुरोकऽशोचिः १. ६६, ३.
दुरोणं १. ११७, २; १८३, १; ४. १३, १; ५. ७६, ४.
दुरोणऽयुः ८. ६०, १९.
दुरोणऽसत् ४. ४०, ५.
दुरोणे १. ६९, २; ३; ७०, २; १०८, ७; ११७, ७; ३. १, १८; १४, ३; १८, ५; २५, ४; ५; ५८, ९; ४. २, ७; ४, ७; २४, ८; २८, ३; ५. ४, ५; ६. १२, १; ७. ७, ४; १२, १; १६, ८; ४२, ४; ६०, ५; ७०, २; ९२, ३; ८. १९, २७; ८७, २; १०. ३७, १०; १०४, ४; ११०, १; १२०, ७.
दुरोषं ९. १०१, ३.
दुरोषाः ४. २१, ६.
दुरोषासः ८. १, १३.
दुर्मदाःऽइव १. ३९, ५.
दुर्य ७. १, ११.
दुर्यः १. ५१, १४; २. ३८, ५.
दुर्यं ८. ७४, १.
दुर्यान् १. ९१, १९; १०. ४०, १२.
दुर्यासु ४. १, ९; १८; २, १२; ७. १, ११.
दुर्योणे १. १७४, ७; ५. २९, १०; ३२, ८.
दुर्हनो इति दुःऽहनो १०. १५५, ३.
दुवः १. ४, ५; १४, १; ३०, १५; ३६, १४; ३७, १४; ३. २, ६; १६, ४; ४. २, ९; ८, ६; ६. १४, १; १५, ६; १६, १८; २९, ३; ८. ३१, ९; ९. ६३, ३; १०. २०, ७.
दुवःऽया ५. ३६, ६.
दुवःऽयु ६. ५१, ४; ७. १८, १४; २५.
दुवःऽयुः ६. ३६, ५.
दुवन्युऽसत् ४. ४०, २.
दुवसः १. १६८, ३.
दुवसनासः ४. ६, १०.
दुवसे १. १६५, १४.
दुवस्य ५. ४२, ११; ४९, २; १०. १४, १.
दुवस्यत ३. २, ८; ५. २८, ६.
दुवस्यत ३. १३, ३; ६. १५, ६; ८. ४४, १.
दुवस्यति ३. ३, १; ७. ८२, ५.
दुवस्यति १. ७८, २; ३. ५१, ३.
दुवस्यथः १. ११२, १५; २१.
दुवस्यथः १. ११९, १०.
दुवस्यन् १. १६७, ६.
दुवस्यन् ३. १, २; १३.
दुवस्यंति १. ६२, १०.
दुवस्यात् १. १६५, १४.
दुवस्युः १०. १००, १२.
दुवस्युवा ८. १०२, २.
दुवस्येत् ६. १६, ४६.
दुवांसि ७. २०, ६; २२, ४.
दुस्तरः ३. २४, १; ४. ३६, ६; ८. ४६, ८; ९; ९. २०, ६.
दुस्तरं १. ६४, १४; ७९, ८; ११९, १०; १३९, ८[२]; २. २, १०; २६, १; ३४, ७; ३. ३७, १०; ५. १५, ३; ३५, १; ७; ३८, २; ९. १६, ३; ६३, ११; १०. ४८, ३; ९३, ८.
दुस्तरस्य ७. ८, ३.
दुस्तरा ५. ८६, २; ८. १०३, ११; १०. ४४, ६.
दुस्तराः ८. ५०, २.
दुस्तरीतवे २. २१, २.
दुस्तरीतु ६. १, १.
दुहते ९. १९, ५; ३४, ५; १०. ७६, ६.
दुहते ८. ६, १९; ५९, ३; ९. ८०, ४; ८५, ९; १०. १०७, ४.
दुहध्यै १०. ६१, १७.
दुहन् १०. १२२, ६.
दुहंतः ८. ७, १६; १०. ९४, ९.
दुहंता १. ११७, २१.
दुहंति १. ६४, ५; ८. ७२, ७; ९. ३४, ३; ६५, १५; ८०, ५; १०. ७६, ७.

दुहंति १. ६४, ६; १३७, ३; ३. ३६, ७; ४. २४, ९; ९. ६२, २०; ७२, ६; ८५, १०; ९५, ४; १०. ७६, ७.

दुहाते इति ४. २३, १०; ६. ७०, २; १०. ११७, ९.

दुहानः ९. ४२, ४; १०७, ५.

दुहाना २. २, ९; ३. ५८, १; ८. १००, ११; १०. ६५, ६; १४९, ४.

दुहानाः ३. १, १४; ६. २८, १; ७. ४१, ७; ४३, ४.

दुहानां २. ३२, ३.

दुहां १. १६४, २७.

दुहां ४. ५७, ७.

दुहितः १. ३०, २२; ४८, १; ९; ४९, २; ५. ७९, २; ३; ८; ९; ६. ६४, ४; ५; ७. ७७, ६; ८१, ३; ५; ८. ४७, १४; १५; १०. १२७, ८.

दुहितरः ४. ५१, १.

दुहितरः ४. ५१, १०; ११.

दुहितरं ४. ३०, ८; ९; १०. ६१, ७.

दुहितरा ६. ४९, ३; १०. ७०, ६.

दुहितरिं १. ७१, ५.

दुहितरिति ६. ६५, ६.

दुहिता १. ३४, ५; ४८, ८; ९२, ५; ७; ११३, ७; ११६, १७; ११७, १३; ११८, ५; १२४, ३; ३. ५३, १५; ५५, १२; ४. ४३, २; ५२, १; ५. ८०, ५; ६; ६. ६३, ५; ६५, १; ७. ६९, ४; ७५, ४; ७८, ४; ७९, ३; ८१, १; ८. १०१, १५; ९. १, ६; ११३, ३; १०. २७, ११; ३९, १२; ४०, ५; ७२, ५; १५९, ३.

दुहितुः १. १६४, ३३; ३. ३१, १; ५. ४२, १३; ४७, १; ७. ६७, २; ९. ७२, ३; ९७, ४७; १०. ६१, ५.

दुहित्रा १. १८३, २.

दुहित्रे १०. १७, १.

दुहीत २. १८, ८.

दुहीयत् २. ११, २१; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९.

दुहीयत् ४. ४१, ५.

दुहीयन् १. १२०, ९.

दुहुः २. ३४, १०.

दुहुः ९. १०८, ११.

दुहे ९. ८९, २; १०. १२, ३.

दुहे १. १०५, २; ८. १४, ३; ३१, ४; ९. १०, ८; ६७, ३२; ६९, १; १०. ६०, ११.

दुह्यते ९. ७४, ४.

दुह्रते १. १३४, ६; १६४, ७.

दुह्रे ३. ५३, १४; ६. ६६, ४; ७. १०१, १; ८. ९, १९.

दुह्रे १. १३४, ६; १३९, ७; ५. ६९, २.

दूत २. ६, ६.

दूतः १. ३६, ५; ४४, २; ९; ५८, १; ७२, ७; ७४, ४; १०५, ४; १६१, ४; १७३, ३; १८८, १; २. ६, ७; ९, २; ३. ३, २; ५, २; ९; ६, ५; ११, २; ५३, ४; ५४, १९; ५५, ९; ४. १, ८; २, २; ७, ८; ९; ९, २; ५. ११, ४; २६, ६; ४३, ८; ६. ८, ४; १५, ९; १६, ६; २३; ६३, १; ७. ३, ३; ७, १; १०, २; ५; ११, ३; ६७, १; ८. ५, ३; २३, ६; २६, १६; ३९, ३; ९; १०१, ३; १०. ४, २; ८, ५; २१, ५; ९८, २; ११०, १; १२२, ५; १३७, ३; १६५, १; ४.

दूतं १. १२, १; ८; ३६, ३; ४; ४४, ३; ११; ६०, १; १६१, ३; ३. ९, ८; १७, ४; ४. ७, ४; ११; ८, १; ५. ३, ८; ८, ६; २१, ३; ६. १५, ८; ७. २, ३; ३, १; १६, १; ४; ८. १९, २१; २३, १८; १९; ४४, ३; १०२, १८; ९. ९९, ५; १०. १२२, ७; १२३, ६.

दूतंऽइव ४. ३३, १.

दूतस्य ७. ३९, ३; ८. ४४, २०.

दूता ७. ९१, २.

दूताऽइव २. ३९, १; १०. १०६, २.

दूतान् ५. ८३, ३.

दूताय १०. १०९, ३.

दूतासः १०. ४७, ७.

दूतीः १०. १०८, २; ३.

दूतौ १०. १४, १२.

दूत्यं १. १२, ४; ४४, १२; ७१, ४; ७४, ७; १६१, १; ४. ८, ४; ९, ६; ७. ९, ५; ८. ३९, १; ९. ४५, २; १०. ९१, ११; ११५, १.

दूत्यानि ४. ७, ८.

दूत्यां ६. ५८, ३.

दूत्याय ७. ११, २; ८. १०३, १३; १०. ७०, ३.

दूदुपत् ३. ३, १.

दूधोत् ७. २१, ४; १०. २६, ७.

दूरकं १०. ५८, १.

दूरके १. २२, ४; ९. ६७, २१; ७८, ५.

दूरं १. २९, ६; ४२, ३; ७. २०, ७; ८. ३०, ३; १०. १६, ९; ४२, ७; ५१, ६; ९७, २१; १०८, ११; १११, ८.

दूरात् १. २७, ३; ३१, १६; १२९, ९; २. २७, १३; ३. ३३, ९; १०; ५९, २; ४. २०, १; ५. १, १०; ८३, ३; ६. १२, १; ३८, २; ४७, २९; ७. ३३, १; २; ८. ५, १; २७, ९; ४५, १७; ९. ९१, ४.

दूरे १. २४, ९; ७९, ११; ९४, ७; ९; १३२, ६; २. ११, ८; २३, ९; ३. ९, २; ३०, २; ४. ४, ३; २३, ७; ५. ७, ४; ७. ७७, ४; ८. ८६, ४; ९. १९, ७; १०. ४९, ६; ५५, १; १०८, १.

दूरेअंते इति दूरेऽअंते १. १८५, ७; ३. ५४, ७.

दूरेऽअर्थः ७. ६३, ४.

दूरेऽआदिशं १. १३९, १०.

दूरेऽआधीः ६. ९, ६.

दूरेऽउपब्दः ७. २१, २.

दूरेऽदृशः १. १६६, ११; ५. ५९, २.

दूरेऽदृशं ७. १, १.

दूरेऽदृशा ६. १०, ४.

दूरेऽदृशे १०. ३७, १.

दूरेऽभाः १. ६५, ५.

दूर्वाः १०. १४२, ८.

दूर्वायाःऽइव १०. १३४, ५.

दूषयंति ७. १०४, ९.

दृंहत् २. १७, ५.

दृंहत १०. १०१, ८.

दृंहत **५.** ४५, २.
दृंहिता **३.** ३९, ४.
दृंहिताः **१.** ५१, ११; **७.** ९९, ५.
दृंहितानि **२.** १५, ८; १७, १; **७.** १८, १३; **८.** १४, ९.
दृंहेथे इति **६.** ६७, ६.
दृक्षसे **१.** ६, ७.
दृतिः **४.** ४५, १; **७.** ८९, २; **८.** ५, १९.
दृतिं **१.** १९१, १०; **४.** ४५, ३; **५.** ८३, ७; **७.** १०३, २; **९.** १, ८.
दृतेःऽइव **६.** ४८, १८.
दृध्रं **४.** १, १५.
दृभीकं **२.** १४, ३.
दृळ्हः **६.** ६७, ६; **८.** २४, १०.
दृळ्हं **१.** ७२, ८; **३.** ३०, ५; ३२, १६; **४.** १, १५; १७, १०; **६.** ३०, ५; ३१, २; **१०.** १४३, २.
दृळ्हस्य **१.** ६३, ५; **६.** ६२, ११; **७.** ७९, ४.
दृळ्हा **१.** ३३, १२; ६४, ३; ७१, २; १२७, ४; **२.** २४, ३; **३.** ४५, २; **४.** १९, ४; २३, ९; ३१, २; **५.** ३९, ३; ८४, ३; ८६, १; **६.** १७, ६; २२, ६; **७.** २७, २; **८.** २१, १६; ४०, १; ४५, १३; **९.** ३४, १; ९१, ४; **१०.** ४८, ६; १२१, ५.
दृळ्हाः **१.** ६१, १४; **६.** २०, ७; ३२, ३; ४३, ३.
दृळ्हानि **१.** १६८, ४; **६.** १७, ५; ३०, ३; ४५, ९; **७.** ७५, ७; **८.** १४, ९; **१०.** १३८, ३.
दृळ्हां **५.** १९, २.
दृळ्हासः **१.** ६३, १.
दृळ्हे **८.** १०३, ५.
दृशतिः **६.** ३, ३.
दृशन् **७.** १०४, २४; **८.** ३३, १९.
दृशये **२.** २४, ८; **५.** ८०, ५; **६.** ९, ५; ४४, ८; **७.** ३५, ५; ८८, २; **९.** ९१, ६; **१०.** १४, १२.
दृशानः **१०.** ४५, ८.
दृशानं **२.** १०, ४.
दृशाना **१.** ९२, १२.
दृशि **५.** ५२, १२.
दृशीकं **१.** २७, १०.
दृशीका **१०.** १०८, ३.
दृशीके **१.** ६६, ५; ६९, ५; **४.** ४१, ६; **१०.** ९२, ७.
दृशे **१.** २३, २१; ५०, १; ५; ५१, ४; ५२, ८; ११२, ५; १२३, ११; १२४, ६; **४.** ११, १[२]; **६.** २९, ३; **७.** १५, ५; ८१, ४; **८.** ४९, ८; ९४, २; **९.** ४८, ४; ६१, १८; ६४, ३०; १०२, ६; **१०.** ५, ५; ६०, ५; १३६, १; १७०, ३.
दृशेन्यः **१०.** ८८, ७.
दृशेयं **१.** २४, १; २.
दृश्यते **१०.** १४६, ३.
दृश्यान् **४.** २, १२.
दृषत्ऽवत्यां **३.** २३, ४.
दृषदं **८.** ७२, ४.
दृषदाःऽइव **७.** १०४, २२.
दृष्टऽवीर्ये **२.** २३, १४.
दृष्ट्वाय **१०.** ३४, ११.
दृह्य **३.** ३०, १५; **१०.** १००, १.
दृह्य **८.** २४, १०.
दृह्यस्व **८.** ८०, ७.
दे **५.** ४१, १.
देदिशती: **८.** १०२, १३.
देदिशते **८.** २०, ६.
देदिशं **८.** ७४, १५.
देदिष्टे **५.** ३१, ३.
देभुः **१.** १४७, ३; **१०.** ८९, ५.
देयां **८.** १, ५.
देव **१.** १३, ११; **२.** ३, ४; **३.** ४, ९; ७, ९; १४, ७; २०, ३; **५.** ४३, ३; **६.** ३, १; ४७, २८; **७.** ९९, २; **१०.** ७०, ९.
देव **१.** १२, ८; १४, १२; २४, ३; २५, १; ३१, १२; ३५, ११; ४२, १; ४४, ११; ५०, ८; ६३, ८; ६८, २; ७४, ९; ९१, १४; २३; ९४, ७; १६; ११४, १०; १६९, ८; १७३, १३; १८९, १; ३; ६; १९०, ५; **२.** १, ४; ११; १५; २, ६; ११, १३; ३३, १५; **३.** ४, १; ६, ६; १५, ६; ४३, ३; ५७, ६; ६२, ७; **४.** २, ११; १३, ४; ४७, १; **५.** २, ११; ३, ४; ५; ८; ६, ४; १५, ५; १७, १; २६, १; ३३, ३; ५०, २; ५; ८१, ४; ५; ८२, ४; ५; ८५, ८; **६.** २, ११; १३, २; ४; १६, ३; १२; ३२; ४३; १८, १४; ३९, १; ४८, ७; ७१, ६; **७.** १, २०; २५; १४, २; १५, ७; १३; ३०, १; ४; ६६, ९; ८९, ५; ९२, १; ९९, १; **८.** १, २३; १२, १५; १९, १७; २३, १८; २६, २५; ४२, ३; ४४, ११; ४८, ९; ६०, १९; ६१, ६; ६५, ४; ७५, २; १०; ८४, ४; १०१, ११; १२; १०२, १; १६; **९.** ६३, २२; ६४, १; ६७, २५; २६; ३०[२]; ९६, ३; १६; ९७, १८; २७; ४२; ४८; ५०; ९८, ४; १०७, ४; १०८, ९; **१०.** ७, १[२]; ६[२]; १५, १२; २३, ७; २६, ४; ४५, ९; ७०, ४; ८५, ५; ९३, ९.
देवऽअवीः **३.** २९, ८; **९.** २४, ७; २८, ६; ६१, १९; ६४, ११; १०५, २.
देवऽअव्यः **९.** ९७, २६; **१०.** ७८, १.
देवऽअव्यं **९.** ७४, ५; १०४, २; **१०.** ३६, ८; ७६, ४.
देवऽआपिः **१०.** ९८, ५; ७; ८.
देवऽआपिना **१०.** ९८, ६.
देवऽआपे **१०.** ९८, २; ४.
देवऽइच्छं **१०.** ६४, ३.
देवऽइच्छेषु **७.** १, २२.
देवऽइषितः **१०.** १३६, ५.
देवः **१.** १, ५; १९, २; ३१, १; ९; ३२, १२; ३५, २; ३; ८; १०; ३६, १३; ५८, ३; ६८, १; ७१, ५; ७३, २; ३; ८४, १९; ९४, १३; १०५, १४; १०६, ७; १२३, ३; १२४, १; १२७, १; १२८, ३; १२९, ११; १३६, ४; १३८, १; १४२, ३; ११; १५७, १;

१६०, १; १८६, १; १८८, १; १९०, ८; **२.** १, ७; ३, १; ४, १; १२, १; १९, ५; २०, ६; २२, १–३; २४, ११; २८, १; ३१, ४; ३८, १; २; ४; **३.** ३, ९; ५, ६; २०, ४; २७, ७; ३३, ६; ५४, १२; ५५, १९; **४.** १, ९; २, १; १०; ५, २; ८, ३; ११, ६; १३, १; २; १४, १; १५, १; १८, १२; २२, ३; २३, ४; ५; ३०, २४[२]; ४३, १; ५३, १; ३; ४; ६; ७; ५४, १; ५८, ३; **५.** १, २; ३, ८; ८, ४; १२, ३; ४२, ३; ५; ४५, १; ८१, ३; ८२, ८; **६.** ११, २; १४, ५; १५, ६[२]; २२, ११; ३०, ४; ४४, २२; ४८, २१; ५०, ८; १३; ५६, १; ५८, २; ७३, ३; **७.** ६, ७; १०, २; १५, १२; १६, ११[२]; ३५, ६; १०; १३; ३८, ३; ४०, १; ४५, १; ३; ६३, १; ३; ६४, ३; ६६, १४; ७६, १; ८६, ७; १००, ३; १०१, २; **८.** १, २२; ११, १; १२, ६; १४, ४; १९, २४[२]; ३९, ७; ८६, ५; ९२, ६; ९३, ११; ९६, २; **९.** ३, १–३; ५; ६; ९; ५, ४; ६, ७; २८, ३; ३७, ६; ४२, २; ५४, ३; ६३, १३; ६४, ९; ६५, २; ६८, २; ७१, ६; ८१, ५; ८७, २; ९५, २; ९७, १; ७; ११; १२; ४८; ९८, ९; ९९, ७; १०३, ६; १०७, १५; १६; १०८, ८; ११०, ६; **१०.** २, २; १०, ५; १२, १; २; ८; १७, ४; १३; २२, ४; ५; २७, १८; ३१, ४; ४८, ११; ४९, १०; ५१, १; २; ६६, ३; ७०, १०; ८१, ३; ८३, २; ८७, १८; ८८, १४; ९२, ११; ९८, २; १००, ३; ९; १०४, ९; ११०, १; १०; १२१, ८; १२४, २; १५०, ४; १५८, ३; १६८, २; ४; १७३, ५; १७४, ३; १७५, १; १७६, ४.

देवःऽइंव **१०.** ३४, ८.

देवःऽदेवः **५.** ४२, १६.

देवकं **७.** १८, २०.

देवऽकर्मेभिः **१०.** १३०, १.

देवऽकामः **२.** ३, ९; **३.** ४, ९; **४.** २५, १; **१०.** ४२, ९; १६०, ३.

देवऽकामा **१०.** ८५, ४४.

देवऽकिल्बिषात् **१०.** ९७, १६.

देवऽकृतं **३.** ३३, ४; **७.** ४, ५; **८.** १९, ६.

देवऽकृतस्य **७.** ९७, ३.

देवऽक्षत्रे **५.** ६४, ७.

देवऽगोपा **१०.** ६३, १६.

देवऽगोपाः **१.** ५३, ११; **५.** ४५, ११; **६.** ६८, ७; **७.** ३५, १३; ६४, ३; १०१, ५; **८.** ४६, ३२.

देवऽजनाः **९.** ६७, २७.

देवऽजाः **१.** १६४, १५; **३.** ५३, ९.

देवऽजातस्य **१.** १६२, १.

देवऽजाताः **९.** ९७, २९.

देवऽजाताय **१०.** ३७, १.

देवऽजामिः **७.** २३, २.

देवऽजुष्टः **१०.** ८८, ४.

देवऽजुष्टं **४.** २६, ४; **१०.** ७०, ४.

देवऽजुष्टा **१.** ७७, १.

देवऽजुष्टैः **५.** ४५, ४.

देवऽजूतः **३.** ५३, ९; **४.** ११, ४; **७.** ८४, ३; **८.** ३१, ३.

देवऽजूतं **७.** २५, ५; **१०.** १७८, १.

देवऽजूते **१०.** १४५, २.

देवऽतमः **४.** २२, ३; **१०.** ३, ६; ७०, २.

देवऽतमाय **२.** २४, ३.

देवऽतया **१०.** २४, ६.

देवता **१.** २२, ५; ५५, ३; १००, १५; १६५, ९; **४.** ४४, २; ५८, १०; **६.** ४, ७; ७०, ५; **७.** १, २३; ८५, ३; **८.** ३, १४; **१०.** ४९, २.

देवऽतातये **१.** १२७, ९[२]; **३.** २६, २; **८.** ३, ५; ६०, १०; ६२, ८; १०१, १; **९.** १५, २; १७, ७; ६५, २७; **१०.** १४१, ६.

देवऽताता **१.** ३४, ५; ५८, १; ९५, ८; १२८, २; **३.** १९, १; **४.** ६, १; **५.** २९, १; **६.** ४, १; ६८, २; **७.** २, ५; ३८, ७; ४३, ३.

देवऽताति **८.** ७४, ३; **१०.** ८, २.

देवऽतातिं **१.** १४१, १०; **३.** १९, २; ४; **४.** ६, ३; ९; **७.** १, १८; ३९, १.

देवऽताते **९.** ९६, ३; ९७, १९; २७.

देवतां **१०.** ९८, १.

देवत्तं **१.** ३७, ४.

देवऽत्रा **१.** ५०, १०; ९३, ९; १०५, १०; १२८, ६; १८२, ५; **३.** १, २२; ८, ७; **५.** २०, १; ६१, ७; ६५, १; **७.** २३, ५; ३४, ९; ५२, १; ६०, १; **८.** १९, १; ३; ३४, ८; १०३, ५; **१०.** १५, ९; ३०, १; ७३, ७; ११०, २; १८८, ३.

देवऽत्वं **१.** ६८, २; ११५, ४; १३६, १; १५१, ९; **३.** ६०, २; **१०.** १५७, ४.

देवऽत्वा **१.** ६९, ३.

देवद्रीचा **१.** ९३, ८; १६३, १२.

देवद्रीचीं **३.** ६, १.

देवऽनिदः **१.** १५२, २; **२.** २३, ८; **६.** ६१, ३.

देवने **१०.** ४३, ५.

देवऽपत्नीः **१.** ६१, ८; **५.** ४६, ८.

देवऽपानः **९.** ९७, २७; **१०.** १६, ८.

देवऽपानं **१.** १६१, ५; **४.** ३५, ५.

देवऽपानानि **१०.** ५३, ९.

देवऽपुत्राः **१०.** ६२, ४.

देवपुत्रे इति देवऽपुत्रे **१.** १०६, ३; १५९, १; १८५, ४; **४.** ५६, २; **६.** १७, ७; **७.** ५३, १; **१०.** ११, ९.

देवप्सरःऽतमः **९.** १०५, ५.

देवप्सरःऽतमं **१.** ७५, १.

देवऽप्सराः **९.** १०४, ५.

देवऽबंधोः **१.** १६२, १८.

देवऽभक्तं **१.** ७३, १०; **४.** १, १०; **१०.** ४५, ९.

देवं १. १, १; १२, ७; १५, ७; २५, १४; ३५, १; ५०, १; १०; ५९, २; १२३, १०; १२८, २; १३८, २; १४४, ५; १६४, १८; २. १३, ५; २२, १–३; ३८, ९; ३. ९, १; ८; १०, १; २०, ५; २६, १; ६२, १२; ४. १, १^{२}; ११, ५; ५. ९, १; १४, २; ३; २१, ३; ४; २२, २; ३; २५, १; ४१, ६; ४२, ११; ४९, १; २; ६. १५, ४; १६, ७; ४१; ४६; ४४, १६; ४९, ९; ५५, ६; ७. ३, १; ७, १; १६, २; २१, १; ९०, ३; ८. ११, ६; १८, २०; १९, १; ३; ३१, १४; ४४, १५; ८९, १; ९. ११, २; ६८, १; १०. १४, ७; १६, १०; ७०, ५; ८६, १; ११०, ९; ११५, ३; १२२, ४; १२८, ७; १३०, ३; १७६, २.

देवऽमादनः ९. ८४, १; १०७, ३.

देवऽमादनं १०. ३०, ७.

देवऽमानं १०. १३५, ७.

देवमानाऽइव १०. १०७, १०.

देवंऽदेवं १. २६, ६; ७. ७९, ५; ८. १२, १९; २७, १३^{२}.

देवऽयज्यया १. ११४, ३; ५. २१, ४; ८. ७१, १२; १०. ६६, ७.

देवऽयज्या १०. ३०, ११; १५; ७०, १; १०७, ३.

देवऽयज्याय ७. ३, ९.

देवऽयतां १. १२१, १; १९०, २; ५. १, ४; ९. ९७, ४६.

देवऽयतीनां १. ३६, १.

देवऽयते १. १५, १२; ७. १८, १.

देवयत्ऽभिः ३. ५, १; १०. ६९, ८.

देवयत्ऽसु १०. ६९, ७.

देवऽयन् २. २६, १; १०. ४६, १०.

देवऽयंतः १. ६, ६; ४०, १; ११५, २; १३९, ३; १७३, ४; ३. ६, १; ८, १; ४; ६; ४. २, १७; ११, ५; ४४, ५; ६. १, २; ७; ७. २, ५; ४३, १; ४७, १; २; ६९, ६; ७३, १; ९२, २; ८. ९, १९; ९. ७४, ८; १०. १३, २; १७, ७; ९१, ९.

देवऽयंतं १. ४०, ७; ४१, ८; ७. ६९, ४.

देवऽयंतीः १. ७७, ३; ३. ६, ३; ७. १०, ३; १८, ३; ६९, २; १०. ३०, १५.

देवऽयवः १. १५४, ५; ७. ९७, १; ८. १०३, ७.

देवऽयाः १. १६८, १; १७७, ४; ३. ८, ५; ५. ७६, १; ७७, २; ७. ६८, ४.

देवऽयानं १. १६२, ४; १०. १८१, ३.

देवऽयानां ७. ७६, २.

देवऽयानात् १०. १८, १.

देवऽयानान् १. ७२, ७; १०. ५१, ५; ९८, ११.

देवऽयानीः १०. ५१, २.

देवऽयानैः १. १८३, ६; १८४, ६; ४. ३७, १; ५. ४३, ६; ७. ३८, ८.

देवऽयावा ७. १०, २.

देवऽयु ९. ११, २.

देवऽयुः ४. २, ७; ५. ४८, २; ६. ३, १; ८. १२, ११; ९. ६, १; १७, ३; ३७, १; ४३, ५; ५६, १; ९७, ४; १०६, १४; १०८, ९; १०. ३२, ५; ५१, ५; १७६, ३.

देवऽयुक्ताः ७. ६७, ८.

देवयुऽभिः ७. ९३, ५.

देवऽयुं १. ८३, २; ४. ९, १; ५. ३४, ५; ६. २८, २.

देवऽयूनां ९. ९६, २४.

देवऽयूनि ७. ४३, २.

देवयो इति देवऽयो ८. ३१, १६.

देवयोः ७. ६१, १.

देवऽयोः १०. १०६, ३.

देवरं १०. ४०, २.

देवऽवतः ७. १८, २२; ८. ३१, १५.

देवऽवंतं ६. ४७, १०; १०. ४७, ३.

देवऽवंदैः १०. १५, १०.

देवऽवातः ३. २३, २; ९. ९६, ९.

देववातऽतमाः ६. २९, ४.

देवऽवातं ९. ६२, ५.

देवऽवाता ४. ३, १५.

देवऽवाताः ३. २०, २.

देवऽवान् ४. २६, ६; १०. ६१, २६.

देवऽवाहनः ३. २७, १४.

देवऽवीः ९. २, १; ३६, २.

देवऽवीतमः १. ३६, ९; ९. २५, ३; २८, ३; ४९, ३; ६३, १६; ६४, १२; १०७, ७.

देवऽवीतये १. १२, ९; २. २३, ७; ३. २१, २; ६. १५, १८; १६, ७; ४१; ६८, १०; ९. ६, ६; १३, २; ३; २०, १; ४५, १; ४६, १; ५४, ४; ६४, १५; ६५, १८; ६७, १७; ७०, ९; १०६, ७; १०७, १२; १०. ३५, १४; ६६, १२.

देववीतिऽभिः ८. ५४, ६.

देवऽवीतिं १. ११३, १२; ७. ६७, ६; ८४, ५; ८. ६८, १३; ९. ८९, ७; ९७, २१; १०. ५३, ३.

देवऽवीतिः १०. ६, ३.

देवऽवीतौ ३. १७, ५; ५. ४२, १०; ७. १९, ४; ९. ९६, १४; ९७, २; ३३.

देवव्यचःऽतमः ५. २२, २.

देवव्यचःऽतमं १. १४२, ५.

देवऽव्यचाः ३. ४, ४.

देवऽशाः ३. २१, ५.

देवऽशंश्रवः ६. ५९, १.

देवशिष्टे इति देवऽशिष्टे १. ११३, ३.

देवऽश्रवः ३. २३, ३.

देवऽश्रवाः ३. २३, २.

देवऽश्रुतं १०. ९८, ७.

देवश्रुत्ऽतमं ९. ६२, २१.

देवऽसुमतिं १०. ९८, ५.

देवऽसेनानां १०. १०३, ८.

देवऽस्तुतः ५. ५०, ५.

देवस्य १. २०, ६; २४, १; २; १२८, ७; १४१, १; १४४, २; १५९, ५; २. ७, २; २२, ४; ३८, ७; १०; ३. १४, ६; १९, ४; २७, ३; ५९, ६; ६२, १०; ११; ४. १, ४; ६^{२}; ७; २, १९; ७, २; १७, ५; ५३, १;

५५, ५; ५. ३, १०; १३, २; ५०, १; ८१, १; ३; ८२, १; ६; ८५, ६; ६. १, ४; ४८, २०; ७१, २; ७. १, २२; ४, ३; ३८, ४; ६; ४०, ५; ५२, ३; ८२, १०; ९७, ८; ८. २, ७; १९, २८; ३१, १२; ५१, ७; ७१, ८; ९२, ६; १०२, १५; ९. ६९, ४; ७०, २; ९७, ११; १०. १२, ३; २२, ४; ५५, ५; ६४, ७; ७९, ४.

देवस्यंऽदेवस्य १०. १, ५; १३६, ४.

देवऽहिंतं १. ८९, ८; ४. ३७, ३; ५. ४२, २; ४; ६. १७, १५; ७. ६६, १६.

देवऽहिंतिं ७. १०३, ९.

देवऽहूर्तमः ३. १३, ६.

देवऽहूर्तमान् ८. ७५, १.

देवऽहूर्तयः १०. ४४, ६.

देवऽहूर्तिः ६. ३८, २; ६५, ५; १०. १८, ३; १२८, ३.

देवहूर्तिऽभिः १. १२, १२; ७. १४, १; ८. ५३, ७; ९. ६८, ७.

देवऽहूर्तिं ७. १४, ३; १०. ५३, ३.

देवऽहूर्तिषु ७. ८३, ७.

देवऽहूर्तौ ६. ५२, ४; ७३, २.

देवऽहूर्त्या १०. ६३, ११.

देवऽहूर्त्यै ८. ३९, ४.

देवऽहूर्ये ७. ८५, २.

देवऽहेळेनं ७. ६०, ८; १०. ३७, १२; १००, ७.

देवा १. २२, २; २३, २; ४६, २; ९२, १८; १८४, ३; ५. ६८, २; ७४, २; ६. ५९, ३; ८. २२, ३; २५, १; २६, ८; ९. ५, ७.

देवा ३. २५, ४; ५३, १; ५. ६७, १; ६. ६८, ६; ८; ७. ६०, १२; ६७, ५; ७४, ४; ८२, ७; ८. ९, ६; ५७, १; १०. २४, ६.

देवाः १. २३, १९; २. २९, १; ४. ३७, १; ५. ४६, २; ८. ४७, ६; ६७, ९; १७; ८३, ६; ९. ६८, १०; १०. ६४, १२; १०१, ९; १३७, १^{२}; १६५, १.

देवाः १. ११, ५; २२, १६; २३, २४; ३१, ११; ३६, ५; ४०, ३; ५; ४५, २; ६५, २; ८०, १५; ८४, १८; ८९, १; २; ७; १०; ९४, ३; ९६, १–७; १००, १५; १०७, २; ११६, १७; १२२, ३; १४; १३५, १; १४७, १; १६१, २; १६३, ८; ९; १६४, ३९; ५०^{२}; १६७, ४; १६९, ५; १७४, १; १७९, ३; १८६, २; ८; १९०, १; २. १, १३; १४; २, ३; १३, ५; २३, २; १९; २४, १६; २७, ४; १०; ३५, १५; ४०, १; ४१, २१; ३. ४, ११; ६, ७; ८; ७, ७; ८, ८; ९; ९, ९; ११, ४; १७, ४; १९, ५; २०, १; ३२, ८; ४९, १; ५१, ८; ५४, २; ५५, २; १८; ५६, ८; ५७, २; ४. १, १८; २, १७; ७, ७; १७, १९; १८, १; ११; १९, २; ३३, ९; ११; ४२, १; १०; ५०, ९; ५. ३, १; ४; ८, ६; २९, ५; ८; ३०, ५; ३१, ८; ५१, १३^{२}; ६९, ४; ८१, ३; ६. ७, १; २; ४; ९, ५; ७; १७, ८; १८, १४; १५; ५०, १४; ५२, १०; १४; १५; ७५, १८; १९; ७. २, २; ११, ४; १६, १२; २१, ७; ३३, ११; ३५, ११; ३९, ३; ४; ४९, ४; ५०, ३; ५१, ३; ५२, ३; ६६, २; ८३, ७; ९१, १; ८. २, १८; १२, २५; १९, २१; २८, ४; ४१, ७; ४८, १; ५७, २; ६२, ७; ६३, १२; ६९, ११; ८१, ३; ८९, २; ९४, २; ९६, ७; ९८, ३; १००, १; ११; ९. १४, ३; ३९, १; ५१, ३; ६१, १३; ६२, २०; ८१, ५; ९२, ४; १०९, २; ११४, ३; १०. १२, ३; ७; ८; १४, ३; १६, ८; १९, ७; २०, ६; २४, ५^{२}; २८, ७; ३५, १३; ३६, १३; ३७, ५; ४६, ९; १०; ५१, ४; ५२, २; ३^{२}; ५३, ४; ५५, ७; ५६, ४; ६१, ७; १४; १९; ६२, ११; ६३, १; ६५, ४; १४; ६६, ६; ६९, ९; ७२, ५; ७३, ८; ७४, २; ८२, ५; ८५, १४; ३१; ३६; ४७; ८७, १५; ८८, १; २; ७; ८; ११–१३; ९०, ६; ७; १५; १६^{२}; ९२, १०; ९५, ७; १८; १०९, ४; ६; ११०, ११; ११२, ६; ११४, १; ३; ११६, ९; ११७, १; १२१, २; १२२, २; ७; १२५, ३; १२८, २; ३; ७; १२९, ६; १३०, ३; १३७, ५; १४१, २; १५१, ३; ४; १५७, १; ४^{२}; १९१, २.

देवाः १. २७, १३; ४०, ६; ८९, ८; ९; ९४, ८; १०५, ३; ५; १६; १०६, २; ११०, ७; ११५, ६; १३९, ७; १७१, २; १८५, ९; २. ३, ४; २८, ३; २९, २; ४–६; ३. ५४, १७; २१; ४. ३४, ११; ५५, १; ५. ४१, १८; ४२, १७; ६. ४७, २०; ५०, ११; ५१, १२; ५२, ८; १३; १७; ५९, ४; ७. ४१, ५; १०४, ११; ८. १८, १५; ३०, २; ४७, २; ८; १०; ४८, १४; ६५, १०; ६७, ७; ८०, १०; ९. ५, ११; ६७, २७; १०. २, ४; ३५, १२; ३६, १०; ३७, ११; १२; ५१, ८; ५२, १; ५; ६३, २; ११; १२; ७२, ६; ७; ७८, ८; ८५, २३; १००, ७; १०३, ११; १०९, ५; १३४, ७; १३७, १^{२}; १५९, ४; १६५, २; ३.

देवाच्यां १. १२७, १.

देवान् १. १, २; १२, ३; १०; १३, १; ४; १२; १४, ६; ९; १२; १५, ४; १२; २३, १०; २७, १३; ३६, ६; ४४, १; ४; ७; ९; ४८, १२; ६७, २; ७१, ३; ७४, ६; ७५, ५; ७६, २; ५; ७७, १; २; १०५, १३; १४; १७; १२०, ४; १३२, ५; १३९, १; १४१, ६; १४२, १; ११; १६१, ६; ७; १६२, २१; १६३, १३; १८५, ८; १८६, १०; १८८, ३; २. ३, १–३; ७; ९, ६; १२, १;

२४, ११; ३६, ४; ३७, ६; **३.** १, १; १७; ३, १; ४, १; ३; १०; ५, ९; ६, ६; ९; ७, ९; १४, ५; १५, ५; १७, १; २; २२, ३; २५, १; २; २७, १; २९, ८; ५४, ५; ८; ५९, ८; **४.** १, २; २, ३; ८, ३; ३०, ५; **५.** १, २; ११; ४, ४; ६; १३, ६; २६, १; २; २८, १; ५; ४०, ८; ५२, १५; **६.** २, ११; ४, १; ११, ३; १५, १८; १७, ८; २८, ३; ४८, ४; ५०, १; २; ४; ९; ५२, ५; **७.** ३, ३; ९, ५[२]; १०, ५; ११, ३; ५; १३, २; १६, ४; १७, २–४; ३०, ३; ३४, ८; ४२, ३; १०४, १४; **८.** २, ४; १०, २; १९, २७; २७, १; ३६, ३; ३९, १; ४४, ३; ४८, ३; ६०, ४; ७५, २; १०२, २; १०३, २; **९.** ११, १; २९, १; ४२, ४; ५; ४४, १; ४५, २; ७१, ६; ८०, १; ४; ९०, ५; ९२, १; ९४, ५; ९७, ४; १२; ४१; ४२; ९८, ७; १०१, ४; **१०.** १, ६; ७; २, १; २; ४; ५; ६, ४[२]; ७, ६[२]; १२, २; ५; १४, ३; ३५, १०; ४९, ११; ५३, २; ५४, १; ५५, ३; ५६, २; ३; ६४, १४; ६५, ९; १५; ६६, १; ४; १३; १४; ७०, ३; ४; ७२, ८; ९३, २; ९५, १८; ९८, ४; १००, ३; ११०, १; १३०, ५; १५०, ३.

देवानां **१.** २२, ९; ३१, १; २; ४३, ५; ४४, १२; ५०, ५; ६८, १; ६९, १; ७०, ३; ८९, २[३]; ९४, १३; १०७, १; ११३, १९; ११५, १; ११६, २; १३३, ७; १३६, ७; १४१, ११; १६०, ४; १६२, ७[२]; १६४, ५; १८५, ४; ६; ११; १८७, ६; १८८, ११; **२.** ३, ९; ४, २; ८, ६; २३, १६; २४, ३; २५, ५; २६, ३; ३२, ६; **३.** १, १७; २, ८; ३, ७; ४, १०; ५, ५; ७, ७; ८, ९; ११, ६; १७, ३; ५४, १९; ५५, १[२]; ५६, १; ६०, ६; ६२, १३; **४.** १, २०; २, १८; १२, ५; २५, ३; २७, १; ३३, २; ९; ३५, ३; ४३, २; ५८, १; **५.** २, ८; ५, १०; २६, ६; ४२, ४; ४६, ७; ६२, १; **६.** १५, ९; १३; ५१, २; १२; ६२, ८; **७.** ७, २; ३५, ३; १५; ४१, ४; ४२, २; ४७, ३; ६५, २; ७६, १; ४; ५; ७७, ३; **८.** १३, २; ३१, ७; १५; ३९, ६; ६०, ६; ६९, ३; ७५, ८; ७९, ९; ८३, १; ९४, ८; १००, १०; १०१, १२; **९.** १, ४; ७६, १; ७८, १; ८१, २; ८३, ४; ८४, ३; ८५, २; ८६, ७; १०; ८७, २; ९५, २; ९६, ६; ९७, ५; ७; २४; ९९, ४; १०७, २२; १०८, ४; १०९, ४; **१०.** २, ३; ४, २; १०, ८; ११, ९; १६, २; ८; २७, २३; ३१, १; ३३, ९; ३५, १; ८; ३६, २; ११; ४८, ११; ५६, १; ६४, १; ७०, २; ९; १०; ७२, १–३; ७७, ७; ८२, ३; ८८, १५; ९३, ३; १०३, ९; १०९, ५; ११०, ३; १०; ११; १२१, ७; १३७, ३; १५०, ४; १६८, ४; १७१, ४.

देवार्य **१.** २०, १; १३५, १; **२.** ३०, १; ३५, ५; **३.** १३, १; **४.** ३, ३; **५.** १६, १; **६.** ६८, ९; **७.** १४, १; ३; १७, ७; ४६, १; ८६, ७; **८.** ८९, १; **९.** ६, ७; ११, २; ९८, १०; १०८, ८; **१०.** ३७, १; १२१, १.

देवासः **१.** २३, ८; ३९, ५; १०५, १२; **२.** ४१, १५; **५.** ४१, १७; **७.** ५९, १; **८.** ७, २७; २७, १०; ३०, १; ३१, ५; ४७, १३; ५४, ३; **९.** ९७, २०; **१०.** १२६, १.

देवासः **१.** ३, ८; ९; १९, ३; ६; २६, ८; ३६, ४; १०; ५२, १५; ५९, २; ८३, २; १०२, १; १०३, ७; १०४, २; १२३, १; १२८, ८; १३१, १; १३६, ४; १६२, १५; **२.** ४, ३; **३.** १, ३; ४; १३; २, ३; ३, ५; ४, २; ८, ६; ११, ९; २९, ७; ९; ५४, ९; **४.** १, १; १९, १; २६, २; ३०, ३; ३५, ८; ५८, ४; **५.** २१, ३; २५, २; २६, ९; **६.** १५, ८; १६, ४८; ४४, ८; ५८, ४; ६७, ५; ९; ६८, ४; **७.** १७, ६; ३२, ९; ४३, ३; ८२, २; **८.** १२, २२; १३, १८; १९, १; २३, १८; २७, १४; २८, १; २९, ७; ८४, २; ९३, १४; ९७, ९; १०२, १७; **९.** १३, ५; १८, ३; ४९, ४; ६५, २४; ७८, ४; १०१, ५; १०२, ५; १०६, ८; १०९, १५; **१०.** ६, ७; २८, ८; ३३, १; ४८, ३; ५३, ७; १०; ६३, ४; ६५, १३; ६६, ९; ११; ७०, ६; ८८, ९; १०; ९३, ७; ११३, ८; १३६, २.

देवासः **१.** ३, ७; १३९, ११[२]; **२.** ३१, २; ४१, १३; **४.** ३६, ५; **५.** ४१, १७; **७.** ४८, ४; **८.** २९, ९; ३०, ४; **१०.** ३५, १४; ६१, २७; ६३, ६; ८; ६४, ११; ६६, १४; १०७, ११; १२८, ४; ५.

देविं **७.** ७५, २; **८.** २७, ५.

देवि **१.** ४८, १; १५; १२३, ३; १०; १२४, १२; **२.** ३२, ६; ४१, १७; **३.** ६१, १; २; **५.** ६१, १७; **६.** ६१, ५; ६; ६४, २; **७.** ७७, ५; ८१, ४; **८.** ९, १६; १७; १८, ४; ६७, १०; **१०.** १७, ८.

देविऽतमे **२.** ४१, १६.

देवी **१.** ४०, ३; ४८, ३; ५६, ४; ९२, ९; १०; १०६, ७; १०९, ४; ११३, १३; १४; **२.** ३, ८; ४०, ६; **४.** १४, ३; ३४, १; ५१, ११; **५.** ३२, १०; ४१, १८; ४३, ११; ५१, ११; ८०, ३; **६.** ५०, ५; ६१, ४; ६४, ५; **७.** ३४, १; ३७, ७; ४०, २; ४; ७८, २; ७९, ३; ९०, ३; **८.** २५, १०; **९.** ५८, २; **१०.** ११, ८; ५९, ७;

७०, ८; १२७, १–३; १३४, १; १४१, २.

देवी इर्ति १. १०६, ३; १६०, १; २. ३१, ५; ३. २५, ३; ४. ५६, २; ५. ३२, ९; ६. ४४, ५; ७. ९७, ८; ८. ९३, १२; १०. ६४, १४; ७०, ६.

देवी इर्ति ४. ५५, ६; ९. ९८, ९.

देवीः ५. ५, ५; १०. ११०, ५; १२८, ५.

देवीः १. १३, ६; ९; २२, ११; २३, १८; ८३, २; १४२, ६; १५३, ४; १७३, ८; २. ३, ५; ८; ३५, ५; ३. ४, ८; ७, २; ३२, ६; ३४, ८; ५६, ४; ४. ३, १२; ५, १३; २२, ७; ५१, ८; ५. ४६, ८; ७. ४७, ३; ४९, १; ५०, ४; ७२, ३; ८५, ३; ९. ५, ५; ८; ९, ६; ६९, ४; १०. ९, ४; १७, १०; ३०, ६; ६४, ९; १०४, ८; १०९, १; ११०, ८.

देवीः १. १२४, १३; ४. ५१, ४; ५; १०; ५. ४६, ७; ८. ८०, १०; १०. ७०, ८; ९७, ४.

देवीं १. ८८, ४; ११५, २; ३. १८, ३; २०, ५; ६१, ५; ४. ४३, १; ५५, ३; ५. ४३, ६; ६९, ३; ८०, १; ६. ५०, १; ७. ३४, ९; ४४, २; ८५, १; ८. १००, ११; १०१, १६; १०. १०१, ९.

देवृषु १०. ८५, ४६.

देवे ७. १०४, १८.

देवेन १. ९१, २३.

देवेभिः १. १, ५; १४, १; २; ३४, ११; १२७, ११; १५९, १; १७९, २; २. २०, ८; ३६, ३; ३. ३, २; ६; १०, ४; १३, १; १५, ६; २४, ४; ४०, ३; ४६, ३; ४७, ३; ५३, १०; ४. ४६, ६; ५६, २; ५. २६, ४; ५१, १; ३; ८; ६. ११, ६; १६, १; २०, २; २५, ८; ५०, १३²; ६७, १०; ७. १४, ३; ३४, १५; ७२, २; ७५, ७; ८. १८, ४; २६, ८; ३८, ७; ७१, ३; ९. ९३, ४; ९७, १; १०. ६, २; ६४, १०; ८२, ५; ८८, ३; ९२, ६; ९८, ६; ९९, १०; १००, १; ११३, २; १२५, ५.

देवेभ्यः १. १३, ११; ५९, ५; ७४, ९; १३९, ७; १४२, ६; १६२, ४; ११; १८७, ११; १८८, १०; २. ३, १०; ३८, १; ३. ९, ५; ६; ३४, ७; ४. ५४, २; ५. ५, ११; ६. ४४, ७; ५१, ८; ७. ९८, ३; ८. १०१, १६; ९. ३, ९; ८, ५; ११, ७; २३, ६; २५, १; २८, २; ४२, २; ६२, २०; २१; ६५, २; ३; ६७, २८; ८०, ४; ८६, ३०; ९९, ७; १००, ६; १०३, ६; १०५, ३; १०६, ६; १०७, २३; १०९, ५; १२; २१; १०. १३, ४; १६, ९; ११; १७, ३; ५१, ७; ६५, ६; ७०, २; ८५, १७; १९; ९७, १; १०४, ८; ११०, ४; ५; ११८, ५; ११९, १३; १५०, १; १८०, ३.

देवेषु १. १, ४; १३, २; १५, ८; १८, ८; २०, ८; २७, ४; ३१, ९; ३६, १२; १४; ७१, ७; ७३, ५; ९१, १; १०२, ९; १०५, १३; १४; ११३, ९; १२५, ५; १२७, ८; १३५, २; १३६, ४; १३९, ९; १४२, ३; ९; ११; १६२, ८; ९; १४; १६; १७९, ६; १८६, ११; २. ४१, १८; २०; ३. १६, ४³; २८, ५; ५३, १५; ५४, ११; ५७, ५; ५९, ९; ४. २, १; १०, ८; १५, १; २; १८, १३; ३१, १५; ३६, ३; ४; ५४, ३; ५. ४, ३; ८; १४, १; २५, ४; ६८, २; ३; ६. १५, ६²; १८; ३६, १; ४६, ६; ७. २, ७; ७, १; ९, १; ११, ५; ८. १०, ३; २५, १; २७, ३; २९, २; ३; ३१, ९; ३२, २८; ३९, ३; ७²; १०; ६०, १५; ६३, १; ६५, १२; १०२, ९; ९. ५, ४; ४४, ३; ५; ४५, ४; ६७, १३; ९४, ३; १०७, १८; १०. ११, ८; १४, १४; ५६, ४; ५७, २; ६२, ६; ६४, २; ७९, ६; ८६, १२; ९८, ११; १०१, ४; १२१, ८; १४४, ६; १५५, ५; १६९, ३.

देवैः १. १२, ४; ३१, ८; ४४, १३; ७६, ४; ९०, १; १०६, ७; १६१, २; १६९, ८; १७३, १२; १८८, १; ३. १, १५; ४, ८; ११; ४. ११, २; ५. ११, २; २९, ९; ६. १५, १६; ४७, २९; ४८, १९; ७. ११, १; २; ३९, ६; ८. ३५, ३; ९. २५, ३; ९७, ६; १०. १५, १०; ९८, ८; १०९, ७; ११३, १; १३५, १; १६९, ४.

देवौ ६. ५९, ५.

देवौ २. ४०, २; ४. ४१, २; ५. ३८, ३; ६६, १; ६८, ४; ८६, ५²; ६. ६०, १४; ८. २५, ४; १०. ९३, ६; १३२, १; १८४, २.

देवौ १. १५२, ७; ४. १५, ९; १०; ५. ७४, १; ७. ७०, ४; ८. ३५, ४; २४.

देव्यै १. १४०, ७.

देव्यस्य ४. ३६, १.

देव्या ९. ७०, ३.

देव्या १. ५३, ५; ८. ९, १६; २३, ५; २७, १३; १०. १७६, २.

देव्याः ४. १, १७.

देव्यां २. ४१, १७.

देव्यै ६. ७५, १५.

देष्ठाय १०. ८५, १५; ११४, २.

देष्ट्री १०. ८५, ४७.

देष्ठः ८. ६६, ६.

देष्णं २. ९, ४; ६. ६३, ८; ७. २०, ७; ३२, २१; ३७, ३; ५८, ४.

देष्णस्य ८. ३०, १९.

देष्णे ४. २०, १०.

देष्णैः ७. ९३, ४.

देहत ७. ५०, २.

देहि ८. १००, १२; १०. ९८, ४.

देहि ३. १४, ६; ४. ३२, २०; ८. ४३, १५; ७१, ३; १०. १४, ११; १९, ६; ८५, २९; १८६, ३.

देह्याः ६. ४७, २; ७. ६, ५.

दैवःऽदासः ८. १०३, २.

दैवऽवातं ३. २३, ३.

दैवऽवाताय ६. २७, ७.

दैवऽवाते ४. १५, ४.

दैवीं ३. ३८, ९; १०. १०७, ३.

दैवीः ९. १०३, ५.

दैवीनां ३. २०, ४; ३४, २.

दैवीं १०. ६३, १०.

दैव्यः १. २७, १२; १५६, ५; २. ३, १०; ६. ५०, १२; ७. ८, ४; ९७, ३; ९. १११, ३; १०. ५७, ५.

दैव्यं १. ३१, १७; ४४, ६; ४५, ९; १०; ११४, ४; २. ५, २; ३०, ११; ४. ४२, ६; ५. १३, ३; ६. १६, ६; ५२, १२; ७. ४४, ५; ८. ४४, ९; ६१, १६; ९. ७१, ८; ८०, ५; ८३, ५; ८४, १; ३; ८६, ४२; १०. ५३, ६; ६३, ९; १००, ६; १४०, ६.

दैव्यस्य १. ३५, ५; २. २३, ७; ३८, ६; ४. २१, १०; ५४, ४; ५. ५७, ७; ६. ३८, १; ७. ५८, १; ८. ४८, २; १०. ९२, ३.

दैव्या १. १३, ८; १४२, ८; १८८, ७; २. ३, ७; ३. ४, ७; ५. ५, ७; ६. ४८, १०; ७. ९७, २; ८. १८, ८; ९. ५, ७; १०८, ३; १०. ६५, १०.

दैव्याः १०. २, १; १२८, ३; १३०, ७.

दैव्यानि १. ७०, १; ९२, १२; १२४, २; ४. ४, ५; ५. ४१, १४; ७. ४, १; ७५, ३.

दैव्यायाः १०. ८७, १९.

दैव्ये ४. ५४, ३; ७. ८९, ५.

दैव्येन २. ३५, ८; ३. ८, १; ४. १, १५; ३४, ८; ७. ३३, ११; ५३, २; ८२, ८; १०. ८७, १२; १०८, ९.

दोः ५. ६१, ५.

दोघं ५. १५, ५.

दोधतः १. ८०, ५; २. २१, ४; ८. ६, ६; १०. ११९, २; १७१, २.

दोधवीति २. ४, ४.

दोधुवत् ९. १५, ४; १०. २३, १.

दोषण्यं १०. १६३, २.

दोषा १. १०४, १; २. ८, ३; ४. २, ८; ११, ६; ५. ३२, ११; ६. ५, २; ३९, ३; ७. १, ६; ३, ५; ८. २२, १४; २५, २१; १०. ४०, २; ४.

दोषाः १. ३४, ३; १७९, १.

दोषां ४. १२, २; ५. ५, ६; १०. ३९, १.

दोषाऽवस्तः १. १, ७; ४. ४, ९; ७. १५, १५.

दोहत् १. १६४, २६.

दोहंते ९. १८, ५; ८६, १८; १०. १३३, ७.

दोहते १. १३४, ४; ८. ९३, ३.

दोहना ८. १२, ३२.

दोहनाः १. १४४, २.

दोहसा १०. ११, १.

दोहसे १. १४१, २; ६. ४५, ७; ६६, १; ५.

दोहसे ५. ४४, १.

दोहेन १०. ४२, २.

दौःऽगहे ४. ४२, ८.

द्यवि १. ३९, ४; ३. २७, १२; ५. ६, ४; ६. ५२, १३; ७. ३१, ९; ८. ६, ४०; ४३, ४; ४४, २९; ९. २६, ३; २७, ५; १०. ९४, ५; १३८, ६.

द्यविंऽद्यवि १. ४, १; २५, १.

द्यवी इति ४. ५६, ५.

द्यां १. ३०, १९; ३१, ४; ३२, ४; ३३, १४; ३५, ७; ९; ५०, ७; ५१, ९; ५२, ११; ६७, ३; ९६, २; १२१, २; ३; १२७, २; १४१, ८; १५४, ४; १६४, ११; १७३, ६; १७४, ३; १८०, १०; २. ११, ५; १५; १२, २; १२; १५, २; १७, २; ५; ३. ३०, ९; ११; ३२, ८; ३४, ८; ३८, २; ४४, ३; ५९, १; ४. ६, २; २२, ३; ३३, १; ३६, १; ४३, ५; ५२, ७; ५. २९, ६; ४६, ३; ५७, ३; ६२, ३; ६३, ३; ६; ८५, ४; ६. १७, ७; ३०, ५; ४७, ५; २९; ४८, २१; ५१, ८; ६४, २; ६७, ६; ७२, २; ७. ३, ३; २४, ५; ८. १४, १४; ४१, १०; ४२, १; ७२, १८; ८९, ५; ९. ८५, ९; ८६, २९; ९६, ३; ९७, १३; १००, ९; १०. ३, ५; १६, ३; ४५, ७; ५५, १; ६३, १०; ६५, ७; ६७, १०; ६८, ११; ७४, २; ८१, २; ६; ८८, ३; ८९, ४; ९२, १; ९४, १२; १११, ५; ११९, ८; १२१, १; १२५, ७; १४९, १; १५३, ३.

द्यांऽइव ४. ७, ३; ३१, १५; ७. ३३, ५; ८. ४१, ८.

द्यावः १. ३५, ६; ५१, १; १५१, ९; २. ३४, २; ३. ३२, ९; ५१, ५; ४. १६, १९; ५७, ३; ५. ४१, १४; ५३, ५; ६. ४, ३; २४, ७; ३८, ४; ७. ८७, ५; ८८, ४; १०१, ४; ८. ६, १५; ७०, ४; ५; १०. १२, ४; ११५, ७.

द्यावा १. ६१, १४; ६३, १; ११३, २; १४३, २; १५९, १; १८५, २–८; २. १२, १३; ४१, २०; ३. ६, ४; ५. ४३, २; ६. ११, १; ७. ४३, १; ६५, २; ८. ९७, १४; ९. ७०, २; १०. १२, १; ३५, ३; ३७, २; ४६, ९; ९१, ३.

द्यावाक्षामा १. ९६, ५; १०२, २; १२१, ११; १४०, १३; ३. ८, ८; ६. ३१, २; १०. ३६, १.

द्यावाक्षामा ८. १८, १६.

द्यावापृथिवी इति १. ३५, ९; ५२, १४; ६१, ८; १०१, ३; ११२, १; ११५, १; ३; १६०, १; २. १, १५; २, ७; ३. ३, ११; २५, ३; २६, ८; ३०, ४; ३२, १०; ५८, ८; ४. ५४, ६; ५६, १; ३; ५. ४७, २; ५१, ११; ५५, ७; ६३, २; ८३, ८; ६. १८, १५; ४४, २४; ७०, १; ४; ५; ७५, १०; ७. ३५, ५; ४४, १; ८. २२, ५; ९६, १६; ९. ६८, १०; ८१, ५; ९७, ४२; १०. १, ७; २, ७; ३१, ७; ८; ३५,

१; ३६, १; ३७, ६; ४७, ८; ६३, ९; ६५, ८; ६६, ४; ६; ९; ७०, १०; ८२, १; ८९, ६; ११०, ९; ११३, १; ५; ११४, ८; १२५, ६; १४९, २.

द्यावापृथिवी इति १. ३१, ८; १५९, ५; १६०, ५; १८५, ११; २. ३२, १; ६. ५०, ३; ७. ५२, १; ५३, २; ३; ८. ४२, २; १०. ९३, १; १०.

द्यावाभूमी इति १०. ६५, ४; ८१, ३.

द्यावाभूमी इति ४. ५५, १; ७. ६२, ४; १०. १२, ४.

द्युक्ष ८. ३३, १५; ६६, ६.

द्युक्षः ६. २४, १; ३७, २; ७. ३४, २४; ९. ५२, १.

द्युक्षऽतमः ९. १०८, १.

द्युक्षं १. १३६, २; ६; २. २, १; ५. ३९, २; ७. ३१, २; ८. ६९, १६; ८८, २; ९. ७१, ४; १०. १८५, १.

द्युक्षऽवचसं ६. १५, ४.

द्युक्षा १. १००, १६.

द्युक्षाय ८. २४, २०.

द्युक्षासः ३. ४०, ५.

द्युऽगत् ८. ९७, ४.

द्युतत्ऽयामा ६. ४९, ४.

द्युतत्ऽयामानं ५. ८०, १; १०. ९३, १२.

द्युतं ९. ५४, १.

द्युतयंत २. ३४, २.

द्युता ६. २, ६; १०. ९९, २.

द्युतानः ४. ५, १०; ७. ८, ४; ९. ६४, १५; ७५, ३.

द्युतानं ६. १५, ४.

द्युतानात् १०. १८१, १.

द्युतानां ७. ७५, ६.

द्युऽभक्तं ४. १, १८; ७. ४०, २.

द्युऽभक्ताः १. ७३, ६.

द्युऽभिः १. ३४, ८; ५३, ४; ११२, २५; २. १, १; ३. ३, २; ३१, १६; ५. १६, २; ५३, ३; ६. ५, ६; ७. १८, २; ३१, ८; ८. ४०, ८; ९. ८६, ४२; ११२, २; १०. ३, ३; ७, ४; ५; ५९, ४; १८९, ३.

द्युऽम्नः ६. १०, २.

द्युऽमत् १. ७४, ९; २. ९, ६; २३, १५; ३. १०, ८; १३, ७; ५. ११, १; १८, ५; १९, ३; २३, ४; ६. १६, ४५; ४८, ७; ७. ८, ६; ६६, १७; ९. १३, ४; ३२, ६; १०. २, ७.

द्युऽमतः ६. १७, १४; ५०, ११.

द्युऽमता ६. ६२, १०.

द्युऽमती ६. ३८, १; ७. ५, ८; १०. ९८, २; ३.

द्युऽमते १. ६३, ३.

द्युमत्ऽतम १. ५३, ३.

द्युमत्ऽतमः ९. ६५, १९; १०८, ३.

द्युमत्ऽतमं १. २८, ५; ५. २४, १; ६. ४४, ९.

द्युमत्ऽतमानि ८. १०१, ७.

द्युमत्ऽसु १०. ६९, ७.

द्युऽमंतः ५. १२, ४; २५, ८; ६९, २; ७. १, ४.

द्युऽमंतं १. ६४, १४; २. ७, १; ३. ३०, १९; ४. ३६, ८; ५. ६, ४; २६, ३; ३१, ४; ६. १७, ४; ७. १५, ७; ९. २९, ६; ६३, २९; ६५, ४; ६७, ३; १०६, ४; १०. ४०, १; ८४, ४.

द्युऽमान् १. ६२, १२; ४. १५, ४; ३१, १४; ५. ३४, ३; ८. ३१, ३; ९. ५, ३; ६१, १८; ६४, १; ८०, २; १०. ११, ७; ६९, ७.

द्युम्नं १. ९, ८; ५४, ११; ७३, ४; ७७, ५; १०३, ३; २. २, १०; ३. ३७, १०; ५९, ६; ५. ७, ९; १०, १; ५०, १; ७९, ७; ६. ५, ७; १९, ९; ३५, २; ४६, ७; ७. २५, ३; ८२, १०; ८. १९, १५; ९. ८, ८; १०८, ९; १०. २९, ४.

द्युम्नऽवत् ३. २९, १५; ९. ६६, ३०.

द्युम्नवत्ऽतमः ६. ४४, १; ९. २, २.

द्युम्नऽवर्धनः ९. ३१, २.

द्युम्नऽवान् ५. २८, ४.

द्युम्नऽश्रवसे ५. ५४, १.

द्युम्नऽसहं १. १२१, ८.

द्युम्नऽसाता १. १३१, १.

द्युम्नस्यं ५. ७, ३; २३, १.

द्युम्नहूतिऽभिः १. १२९, ७[२].

द्युम्नऽहूतौ ४. १६, ९; ६. २६, ८.

द्युम्ना ४. ४, ९; ५. ३८, १; ८६, १; ६. १९, ६; ६८, ७; ८. १९, ३३; २६, २२; १०. ४२, ६.

द्युम्नानि १. १२२, १२; १३९, ८; ३. ४०, ७; ४. ४, ६; ५. २८, ३; ८. २८, ५; ९. ४०, ४; ६१, ११.

द्युम्नाय ६. ६०, ११; ८. ९, २०; २४, १२; ९. १०९, ११.

द्युम्निऽतमः ८. ९२, १६.

द्युम्निऽतमं ८. १९, ६.

द्युम्निनः १. १३८, २[२].

द्युम्निनं ३. ३७, ८.

द्युम्निनी ८. ७४, ९.

द्युम्निन्ऽतमः १. १२७, ९; १७५, ५.

द्युम्नी १. ३६, ८; ९१, २; ८. ८७, १; ८९, २; ९३, ८; १०३, ९; ९. १०९, ७; १०. ६९, ५; ९६, ३; १५९, ४.

द्युम्ने ९. ६१, २९.

द्युम्नेन १. ४८, १; १६; ३. २४, ३; ६. ५, ५; १६, २१; १८, ७.

द्युम्नेभिः १. ९१, २; ६. ६१, १३; ७. ७, ६.

द्युम्नेषु ३. ३७, ७.

द्युम्नैः १. ७८, १–५; ४. १२, १; १६, १९; ६. ४४, १; ८. ५, ३३; १९, १४; २०, १६; ७४, ९; १०. ११५, ७.

द्यून् १. ३३, ११; ७१, ६; ११३, १३; ११६, २४; १२१, ३; ७; १४८, ४; १६७, १०; १८०, ८; १९०, ४; २. १३, १३; १४, १२; २७, ८; २८, २; ३. २३, २; ४. ४, ८; ९; ३३, ७; ४३, ३; ५. ६९, १; ८६, ५; ६. ६७, ६;

१०. ११, ७; १७, ११; २७, ५; ४५, ११.

द्योः १. ११५, ५; ४. २७, ३; ३८, ८; ६. ६६, ८; ६७, ६; १०. ६८, ४.

द्योर्तनः ८. २९, २.

द्योतना १. १२३, ४.

द्योर्तनाय ६. २०, ८.

द्योतनिं ३. ५८, १; १०. १२, ७.

द्योर्तमानां १०. १७७, २.

द्योतयत् ६. ३९, ३.

द्यौः १. ८, ५; २२, १३; ५२, १०; ५७, ५; ६५, २; ७१, ८; ८९, ४; १०; ९०, ७; ९४, १६; ९५, ११; ९६, ९; ९८, ३; १००, १९; १०१, ११; १०२, ११; १०३, ८; १०५, १९; १०६, ७; १०७, ३; १०८, १३; १०९, ८; ११०, ९; १११, ५; ११२, २५; ११३, २०; ११४, ११; ११५, ६; १३०, १०; १३१, १; १३३, ६; १६४, ३३; १९१, ६; २. २, ५; ३. ६, ३; ३२, ११; ५४, १९; ४. १, १०; १७; १७, १; २; ४; १३; २१, १; २२, ४; ५१, ११; ५. ३६, ५; ४१, ११; ४५, २; ३; ५४, ९; ५८, ६; ५९, ८; ६. १२, २; १७, ९; २०, १; ३६, ५; ४८, २२; ५०, १३; ५२, २; ६८, ४; ७०, ६; ७२, ३; ७. ५, ४; ७, ५; ३४, २३; ८४, २; ८. ७, २६; १५, ८; २०, ६; ४०, ४; ५६, १; १००, १२; ९. ८६, ९; १०. १०, ५; २९, ६; ३६, २; ४४, ८; ४५, ४; ८; ५९, ३; ७; ८; ६३, ३; ६७, ५; ७४, २; ८५, १; ७; १०; ८८, २; ८; ९०, १४; ९२, ४; १२१, ५; १३२, १; ४; ६; १३३, ५; १७३, ४.

द्यौः ६. ५१, ५.

द्यौःऽइव २. ४, ६; ५. ५७, ४; ६. ५८, १; ७. ८७, ६; ८. ४१, ५.

द्यौत् ४. ४, ६.

द्रप्सः ६. ४१, ३; ७. ८७, ६; ८. १७, १४; १९, ३१; ९६, १३; १५; ९. ६९, २; ८९, २; ९६, १९; १०. १७, ११; १२; ९८, ३; १२३, ८.

द्रप्सं ४. १३, २; ७. ३३, ११; ८. ९६, १४; ९. ७८, ४; ८५, १०; १०. ११, ४; १७, ११.

द्रप्सस्यं ९. ७३, १.

द्रप्साः १. १४, ४; ९४, ११; ५. ६३, ४; ९. १०६, ८; १०. ९८, ४.

द्रप्साःऽइव ८. ७, १६.

द्रप्सान् ९. ९७, ५६.

द्रप्सासः ९. ६, ४.

द्रप्सिनः १. ६४, २.

द्रव ८. ४, ८; १७, ११; ६४, १२.

द्रव ५. ३१, २; ६. ४८, १६; ८. ४, १२; १३, १४; ६४, १०; ८२, १; ९. ८७, १; १०. १४, १०.

द्रवः ४. ४०, २.

द्रवत् १. २, ५; ४४, ७; ३. ३५, २; ६. ४५, ३२; ७. १०, २; ८. ५, ७; ४९, ५.

द्रवतः ४. ४०, ३; १०. १०२, ६.

द्रवत्ऽअश्वं ४. ४३, २.

द्रवतां ३. १४, ३.

द्रवत्ऽचक्रेषु ८. ३४, १८.

द्रवत्पाणिऽभिः ८. ५, ३५.

द्रवत्पाणी इति द्रवत्ऽपाणी १. ३, १.

द्रवतं ४. ३८, ३.

द्रवता १०. ६१, ३.

द्रवति ४. ६, ५; ६. ७५, ११.

द्रवती ५. ४१, १८.

द्रवतु ४. १६, १.

द्रवंतु १०. ११२, २.

द्रवय ८. ४, ११.

द्रवयति ६. ३, ४.

द्रवयत्ऽसंखं १०. ३९, १०.

द्रवयंत १०. १४८, ५.

द्रवयित्नवः ९. ६९, ६.

द्रवरः ४. ४०, २.

द्रविः ६. ३, ४.

द्रविणः ३. ७, १०.

द्रविणःऽदः १. १५, १०.

द्रविणःऽदः २. ६, ३; ३७, १–३; १०. ७०, ९.

द्रविणःऽदसः २. ३७, ४.

द्रविणःऽदाः १. १५, ७–९; ९६, ८[४]; २. १, ७; ३७, ४; ५. ४६, ४; ७. १६, ११; ८. ३९, ६; १०. २, २; ९२, ११.

द्रविणःऽदां १. ९६, १–७.

द्रविणःऽदेषु १. ५३, १.

द्रविणःऽदौ ५. ४३, ९.

द्रविणःऽवित् ९. ९७, २५.

द्रविणं १. ९४, १४; १२१, २; २. २३, १५; ३. १, २२; २, ६; ५८, ६; ६१, ६; ४. ५, ११; १२; ११, ३; २०, ९; २३, ४; ४१, ९; ५१, ७; ५४, १; ५. २८, २; ५४, १५; ६. ६९, १; ६; ७०, ५; ७. ९, १; १०, ३; ३५, १०; ९. ९६, १२; ९७, ५१; १०. ३१, २; ३५, १३; ३६, १३; ३७, १०; ४५, ११; ६१, १२; ६७, ७; ७०, ७; ८०, ४; ८१, १; ८२, ४; १२५, २; १२८, ३.

द्रविणसः १. १५, ७; ९६, ८; ४. ३४, ५; १०. ६४, १६.

द्रविणस्यवः ५. १३, २.

द्रविणस्युः ६. १६, ३४; १०. ६४, १६.

द्रविणस्युं २. ६, ३.

द्रविणस्वंतः ९. ८५, १.

द्रविणा ३. ८, १.

द्रविणानि २. २१, ५; ६; ४. ३३, १०; ५८, १०; ५. ४, ७; ६. ५, १; ९. ७८, ५; १०९, ९.

द्रविणाय ३. १०, ६.

द्रविणो इति ६. ६९, ३.

द्रविणोदाःऽइव ९. ८८, ३.

द्रविता ६. १२, ३.

द्रवित्नवः ८. ७४, १४.

द्रवित्नुं १०. ११, ९.

द्रवित्नवः १०. ४९, ९.

द्रवित्नवा ८. ९२, १५.

द्रुह्यत् २. ११, १५.

द्राघिष्ठाभिः ३. ६२, १७.

द्राघीयः १. ५३, ११; ८. १८, १८.

द्राघीयांसं १०. ११७, ५.

द्राघ्मा १०. ७०, ४.

द्रांतु १०. ८५, ३२.

द्रापिं १. २५, १३; ४. ५३, २; ९. ८६, १४; १००, ९.

द्रापिंऽईव १. ११६, १०.

द्रासत् ८. ४७, ७.

द्रुऽअन्नः २. ७, ६; ६. १२, ४; १०. २७, १८.

द्रुघः ५. ४०, ७.

द्रुघानि ७. ८६, ५.

द्रुऽघ्नं १०. १०२, ९.

द्रुणः १. १६१, १.

द्रुणा ५. ८६, ३; ८. ९६, ११; ९. १, २; ६५, ६; ९८, २.

द्रुऽपदे ४. ३२, २३.

द्रुपदेषु १. २४, १३.

द्रुऽसत् ९. ७२, ५.

द्रुऽसदं १०. ११५, ३.

द्रुऽसद्वा ६. ३, ५.

द्रुहः १. १२१, ४; १३३, १; ३. ३१, १९; ७. ६१, ५; ७५, १; ८. ३७, २.

द्रुहः २. २३, १६; १७; ३५, ६; ४. ४, १५; २८, २; ५. ७४, ४; ६. २०, ५; ७. १६, ८; ५९, ८; १०४, ७; ८. ४७, १; ९. ७१, १; १०. २५, ८; ४८, १०; ७३, २.

द्रुहन् १. ५, १०.

द्रुहं ४. २३, ७.

द्रुहंऽतरः १. १२७, ३[२].

द्रुहा ७. १०४, ७; १७.

द्रुहे २. ३०, ९.

द्रुह्यवः ७. १८, ६; १४.

द्रुह्यवि ८. १०, ५.

द्रुह्युं ७. १८, १२.

द्रुह्युषु १. १०८, ८.

द्रुह्यौ ६. ४६, ८.

द्रुन्हणे ६. २२, ८; १०. ९९, ७.

द्रुन्हाणः १. २५, १४.

द्रूणानः ४. ४, १.

द्रोः १०. १०१, १०.

द्रोघंऽमित्रान् १०. ८९, १२.

द्रोघऽवाचः ७. १०४, १४.

द्रोघाय ६. ६२, ९.

द्रोणंऽआहावं १०. १०१, ७.

द्रोणं ६. ४४, २०; ९. ९३, १.

द्रोणऽसाचं १०. ४४, ४.

द्रोणा ९. ६७, १४.

द्रोणानि ९. ३, १; २८, ४; ३०, ४; ३३, २; ३७, ६; ६५, १९.

द्रोणिऽअश्वासः १०. ९९, ४.

द्रोणे ६. २, ८; ३७, २.

द्रोणेषु ९. १५, ७.

द्रोण्यः ५. ५०, ४.

द्रुके इति १०. ५९, ९.

द्वयान् ६. २७, ८.

द्वयाविनः १. ४२, ४; २. २३, ५; ९. ८५, १.

द्वयीभिः ९. ७२, ३.

द्वयुः ८. १८, १४.

द्वयुं ८. १८, १५; ९. १०४, ६; १०५, ६.

द्वयेन १. १४७, ४; ५; ५. ३, ७; १२, २.

द्वयोः १. ८३, ३; ६. ४५, ५; ८. ४५, ३४.

द्वरः १. ५२, ३.

द्वरिषु १. ५२, ३.

द्वा १. १२१, ३; १४४, ४; १६१, ३; १६२, १९; १६४, २०; ४. ३०, १९; ३३, ५; ६. ६७, १; ७. १८, २२; ८. २९, ८; ९; ७२, ७; ९. ८६, ४२; १०. १७, २; २७, १७; २३; ४८, ७.

द्वादश १. २५, ८; १६४, ४८; ४. ३३, ७; १०. ११४, ५.

द्वादशऽअरं १. १६४, ११.

द्वादशऽआकृतिं १. १६४, १२.

द्वादशस्य ७. १०३, ९.

द्वाऽद्वा ८. ६८, १४; १०. ४८, ६.

द्वाभ्यां २. १८, ४; १०. ६७, ४.

द्वारः १. १३, ६; १३०, ३; १४२, ६; २. ३, ५; ७. १७, २; ९. ५, ५.

द्वारः ५. ५, ५; १०. ७०, ५; ११०, ५.

द्वारा १. १२८, ६; ३. ५, १; ४. ५१, २; ८. ३९, ६; ६३, १; ९. १०, ६.

द्वाराऽइव ८. ५, २१.

द्वारौ १. ४८, १५; ७. ९५, ६.

द्विः १. ५३, ९; १२२, १३; ४. ६, ८; ६. ६६, २; ८. ७०, १२; ९. ९८, ६; १०. १२०, ३.

द्विऽजन्मा १. १४०, २; १४९, ४; ५.

द्विऽजन्मानः ६. ५०, २.

द्विऽजन्मानं १. ६०, १.

द्विऽजाः १०. ६१, १९.

द्विऽजानिः १०. १०१, ११.

द्विता १. ३७, ९; ६२, ७; १२७, ७; १३२, ३; २. ४, २; ३. २, १; १७, ५; ४३, ६; ४९, २; ४. ४२, १; ६. १६, ४; १७, ९; ४५, ८; ४८, १३; ७. २८, ४; ८६, १; ८. १, २८; १३, २४; २४, २५; २८, १; ७०, २; ७१, ११; ८३, ८; ८४, २; ९३, ३२; ९. ९४, २; ९७, २४; १०२, १; १०. ४८, ९.

द्विताय ५. १८, २; ८. ४७, १६.

द्वितीये १. १४१, २; २. १८, २; १०. ४५, १.

द्वितीयया ८. ६०, ९.

द्विधा १०. ५६, ६.

द्विऽधाराः १०. ३०, १०.

द्विऽपत् १. ४९, ३; ९४, ५; १२४, १; १०. ९७, २०.

द्विऽपदः ६. ७१, २; १०. ११७, ८; १२१, ३.

द्विऽपदा १. १६४, २४.

द्विऽपदां १०. ११७, ८.

द्विऽपदी १. १६४, ४१.

द्विऽपदे १. ११४, १; १५७, ३; ३. ६२, १४; ५. ८१, २; ६. ७४, १; ७. ५४, १; ९. ६९, ७; १०. ३७, ११; १६५, १.

द्विऽपात् ४. ५१, ५; १०. २७, १०; ११७, ८.

द्विऽपादः ८. २७, १२.
द्विऽपादे १. १२१, ३.
द्विऽबंधुः १०. ६१, १७.
द्विबर्हऽज्मा ६. ७३, १.
द्विऽबर्हसः १. १७६, ५; ८. १५, २; १०. ६१, १०.
द्विऽबर्हसं ९. ४, ७; ४०, ६; १००, २.
द्विऽबर्हाः १. ७१, ६; ११४, १०; ४. ५, ३; ५. ८०, ४; ६. १९, १; ७. ८, ६; २४, २; १०. ११६, ४.
द्विऽमाता १. ३१, २; ११२, ४; ३. ५५, ६; ७.
द्विऽवर्तनिः १०. ६१, २०.
द्विऽशवसं ९. १०४, २.
द्विषः १. ४१, ३; ९०, ३; ९७, ७; १३३, ७^{२}; २. ७, ३; ५. २५, ९; ४४, १२; ६. ४५, ६; ५१, १६; ६०, ६; ६१, ९; ७. ५९, २; ८. ११, ३; १३, २१; १६, ११; २६, ५; ४३, २३; २६; ४५, १०; ४०; ६१, १३; ६९, १४; ७९, ९; ९. ८, ७; १३, ८; ६१, २८; ६३, २६; १०. १२६, १–७; १८७, १.
द्विषः २. ७, २; ३. १५, १; ५. २५, १; ५०, ३; ६. २, ४; ११; ६८, ५; ८. ७१, १; ९. ११०, १; १०. २४, ३.
द्विषतः ६. ४७, १९; १०. १५२, ५.
द्विषतां १०. १६४, ४.
द्विषते १. ५०, १३; १०. १२८, ५.
द्विषंतं १. ५०, १३.
द्विषे १. ३९, १०.
द्विषां ७. ३४, १३.
द्विष्मः ३. ५३, २१; १०. १६४, ५.
द्वीपं १. १६९, ३.
द्वीपानि ८. २०, ४.
द्वे इति १. ९५, १; १५५, ५; १८५, २; ३. २, ९; ३०, ११; ५६, २; ४. ५८, ३; ५. ४७, ५; ७. १८, २२; १०. २७, ७; ८५, १६; ८८, १५; १६.
द्वेषः १. ३४, ११; ४८, ८; १५७, ४; १६७, ९; २. २३, २; ४. १०, ७; ५. २०, २; ८०, ५; ६. ४४, १६; ४६, १२; ४७, १२; १३; ७. ५६, १९; ५८, ६; ७७, ४; १०४, २; ८. १८, ११; ४४, ११; ६७, २१; ७१, १५; ७९, ४; १०. ६३, १२; ७७, ६.
द्वेषःऽभिः ७. ६०, ९.
द्वेषःऽभ्यः ८. ७९, ३.
द्वेषःऽयुतः ५. ९, ६.
द्वेषःऽयुतं ४. ११, ५.
द्वेषांसि २. ६, ४; २७, ७; २९, २; ३. १६, ५; २७, ३; ४. १, ४; ५. ४५, ५; ८७, ८; ६. १०, ७; ५९, ८; ८. १८, ५; ५३, ४; ९. २९, ४; १११, १; १०. १००, ९.
द्वेष्टि ३. ५३, २१; १०. ३४, ३; १६४, ५.
द्वौ १. ३५, ६; १९१, १; ५. ६२, ६; १०. १३७, २.
द्वौऽइव १. २८, २.

ध

धक् १. १७८, १; २. ११, २१; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; ६. ६१, १४; ७. १, २१.
धक्तं १. १८३, ४.
धक्षत् १. १३०, ८; २. ४, ७; ६. ३, ४.
धक्षतः १०. ९१, ७.
धक्षि १. ७६, ३.
धक्षि १. १४१, ८; २. १, १०; ४. ४, ४; ६. १८, १०.
धक्षुपः १. १४१, ७.
धक्षोः २. ४, ४; १०. ११५, ४.
धत् ४. २७, ५^{२}.
धत्त १. १७१, १; ४. ३३, १०; ७. ५६, २०; ९. ६८, १०.
धत्त १. ६४, १५; ८५, १२; २. १२, ५; ४. ३४, १०; ५८, १०; ५. ६०, ७; १०. १५, ७.
धत्तन १. २०, ७; ६४, १४; १०३, ५; ५. ५३, १३; १०. ३०, १४.
धत्तं १. ४७, १; १८०, ९; ७. ६७, १०; ९७, १०; ८. ८, १३; ३५, १०; २२; १०. ४०, १३.
धत्तं १. ४७, ६; ९३, २; ७; १२; १५९, ५; ४. ४२, १०; ४९, ४; ५७, ८; ६. ५२, १६; ६९, १; ६; ७४, ३; ७. ५३, ३; ८४, ४; १०४, २; ८. ८, १५; ९, २; ३५, १०^{२}; ५९, ४; ७^{२}.
धत्तात् ३. ८, १.
धत्तां ४. ५१, ११.
धत्तां १०. १८४, २.
धत्ते १. ८५, ९; ६. १३, ४.
धत्ते १. ४०, ४; ९५, १०; १२२, ९; १२५, १; ३. १०, ३; ४४, ४; ५. १८, ३; २८, २^{२}; ८. २३, २१; १०३, ४; ५; ९. ७६, २.
धत्थ ४. ३४, १०; ८. २७, २१.
धत्थ ५. ५४, १४; ७. ३७, २.
धत्थः ६. ६८, ६; ७. ६८, ६.
धत्थः १. १५७, ५; ६; ५. ६३, ७.
धत्से ८. ९६, ५.
धत्स्व १०. ८७, २.
धनंऽअर्चे १०. ४६, ६.
धनऽजित् १०. १७०, ३.
धनऽजितं २. २१, १.
धनऽदाः ६. १९, ५; ७. ३२, १७; १०. ११६, ९; १४१, १.
धनऽदां १. ३३, २; १०.
धनं १. ३६, ४; २. १३, १०; ३. २, १२; ६. ४५, २; १२; १५; ७. ३२, १२; ८. १९, १८; ६८, ९; ८०, ८; ९. ९७, ३८; १०. ३१, ११; ३४, १०; ४२, ५; ४८, ५; ६४, ६; ८४, ७; ९७, ८.
धनंऽजय ९. ४६, ५.
धनंऽजयः १. ७४, ३; ९. ८४, ५.
धनंऽजयं ३. ४२, ६; ६. १६, १५; ८. ४५, १३.
धनंऽधनं २. २३, १३; ९. ८५, ८; १०. १५६, १.

धनऽभक्षेषु १०. १०२, १.
धनयन् १. ७१, ३.
धनयंत १. १६७, २.
धनयंते १. ८८, ३.
धनऽसाः २. १०, ६; ८. ३, १५; १०. ६५, १०.
धनंऽसातये १०. १५०, ४.
धनंऽसातौ १०. १५०, ४.
धनऽसां १. ११२, ७; १०; ८. ८६, ४.
धनऽसैः १०. ६७, ७.
धनऽस्पृत् ३. ४६, २.
धनऽस्पृतं १. ३६, १०; ६४, १४; ५. ८, २; ६. १९, ८; ८. ७, १८; ५०, ६; ९. ६२, १८; १०. ४७, ४.
धनंस्य ६. ४४, ९; ८. ३, ५; ९. ९७, २९.
धना १. ६४, १३; ८१, ३; १०२, १०; १३०, ६; १५७, २; २. २४, ९; १३; २६, ३; ५. ३२, ९; ९. ६१, २३; ७९, २; १०. ३४, १२; ४२, ९; १२०, ४; १४७, ४.
धनानां १. ४, ९; ३१, ८; १०२, ५; १२४, ७; ३. १८, ५; ३०, २२; ४. २०, ३; ५. ४२, ५; ७; ६. २६, ८; ९. ९६, २०; १०. ३०, ११; १३९, ३.
धनानि १. ३०, १६; ४२, ६; १००, ९; १३; १०८, १३; १३०, ६; ७[३]; ४. ५०, ९; ८. १४, ६; ९. ६५, ९; ७९, २; ९०, ३; १०. ४२, १०; ४८, १.
धनाय १. १००, ८; १०४, ७; ४. २३, १; ८. ७१, ५; ९. ९७, ४; १०९, १०.
धनिनः १. १५०, २.
धनिनं १. ३३, ४; ४. २, १५.
धनिष्ठा १०. ७३, १.
धनुः ६. ७५, २; ८. ७२, ४; ७७, ११; ९. ९९, १; १०. १८, ९; १२५, ६.
धनुऽस्तरौ ४. ३५, ५.
धनुत्रीः ३. ३१, १६; ९. ९३, १.
धनुंऽअन्यः ८. ३, १९.
धनुं १०. २७, १७.
धने १. ३१, ६; ४०, २; ५४, ६; ११६, १५; १३२, १; ५; ६. ४५, ११; १३; ६१, ५; ८. ३, ९; ५, २६; ८, २१; ४९, ९; ५०, ९; ९२, ९; ९. ५३, २; १०. ६३, १४; १४७, ३.
धनेऽधने ५. ३५, ७.
धनेन १०. १८, २.
धनेषु ७. ३८, ८; ८. १६, ५.
धनोः १. ३३, ४; १४४, ५; १०. ४, ३.
धन्या ३. १, १६; ५. ४१, ८; ६. ११, ३.
धन्याय ९. ८६, ३४.
धन्व १. ३५, ८; २. ३३, १०; ३८, ७; ४. ३३, ७; ५. ७, ७; ६. १२, ५; ९. ९७, ३; १०. ८६, २०; ८९, ६; १८७, २.
धन्व ९. ७५, ५; ९७, १६–१९; ५२, १०५, ४; १०६, ४; १०९, १; ११०, १.
धन्वऽअर्णसः ५. ४५, २.
धन्वऽइव ३. ४५, १; १०. ९३, ६.
धन्वऽचरः ५. ३६, १.
धन्वऽच्युतः १. १६८, ५.
धन्वन् १. ३८, ७; ९५, १०; ११६, ४; १३५, ९; ६. ३४, ४; ७५, ३; ९. ६९, १; ७९, ३.
धन्वनः १०. ११६, ६.
धन्वना २. २४, ८; ५. ५३, ६; ६. ७५, २[४]; १०. ११५, ६.
धन्वन्ऽइव १०. ४, १.
धन्वंति ९. ९७, २०.
धन्वंतु ९. ७७, ३; ७९, १; २; ९७, २६.
धन्वऽसहा १. १२७, ३.
धन्वसि ९. २४, ३; ८६, ३४.
धन्वऽसु ५. ५३, ४; १०. ६३, १५; १३३, १.
धन्वाति ३. ५३, ४.
धन्वानि ४. १७, २; १९, ७; ५. ८३, १०; ६. ५९, ७; ६२, २; ८. २०, ४; १२.
धम १०. १४५, २.
धमतः ९. ७३, १.
धमति ५. ९, ५; १०. ८१, ३.
धमथः ५. ३१, ९.
धमनि २. ११, ८.
धमंतः १. ८५, १०; २. ३४, १; ४. २, १७.
धमंतं ८. ९६, १३.
धमंता १. ११७, २१.
धमंति ८. ७, १६; ९. १, ८.
धमंति ९. ७३, ५.
धमंतीः ३. ३०, १०.
धमितं २. २४, ७.
धम्यते १०. १३५, ७.
धयति १. १७९, ४; २. ३५, ५; १३; ८. ९४, १.
धरीमणि १. १२८, १; ९. ८६, ४.
धरुणः १. ७३, ४; ५. १५, १; ९. २, ५; ७२, ७; ७४, २; ८६, ८; ८७, २; ८९, ६; १०. ५, १; ४५, ५.
धरुणं १. २३, १३; ५६, ५; ६; १२१, २; ५. १५, २; ५; ७. ३४, २४; ९५, १; ८. ७२, १५; ९. १०७, ५; १०. ४७, २; ८३, ७; १११, ४.
धरुणऽह्वरं १. ५४, १०.
धरुणानि ४. २३, ९.
धरुणाय १०. ५६, २; ६०, ८.
धरुणे ५. १५, २; ९. ८९, ५; १०. ४४, ४; १७०, २.
धरुणेषु १. ५२, २; ३. ३, १; ९. ७३, ३; १०. ५, ६.
धर्णसि १. १०५, ६.
धर्णसिः ५. ४३, १३; ९. २, २; २३, ५; ३७, २; ३८, ६.
धर्णसिं १. १४१, ११; ५. ८, ४; ८. ६, १४; ९. १४, २; २६, ३; ९९, ५.
धर्णिः १. १२७, ७.
धर्तः १. १०२, ५.
धर्तरि २. २३, १७; ९. ८६, ४२.
धर्ता १. ११, ४; ३. ४९, ४; ४. ५३, २; ५. १, ६; १५, १; ७. ३५, ३; ८. ४१, ५; ९. ३५, २; ७६, १; १०९, ६; १०. ६१, ९; ६५, १३; १४९, ४.

धर्तारः १०. १०, २; ६६, १०.
धर्तारं ५. ९, ३; ९. २६, २; ६५, ११.
धर्तारा १. १७, २; ५. ६७, २; ६९, ४.
धर्मं ३. १७, १; ५; ७. ८९, ५; १०. ५६, ३; १४९, ३.
धर्मऽइव ८. ६, २०.
धर्मऽकृते ८. ९८, १.
धर्मणः ६. ७०, ३; ९. ३५, ६.
धर्मणा १. १३४, ५²; १६०, १; २. १३, ७; ५. ६३, ७; ७२, २; ६. ७०, १; ९. २५, २; ६३, २२; १०७, १५; १०. १६, ३; ४४, १; ५; ६५, ५; १७५, १.
धर्मणां १. ५५, ३; ८. ४३, २४.
धर्मणि १. १५९, ३; ३. ३८, २; ९. ९७, २२; १०. १६७, ३.
धर्मणे ४. ५३, ३; १०. ५०, ६; ८८, १.
धर्मन् ५. १५, २; ९. ७, १; ११०, ४; १०. २०, २; १७०, २.
धर्मऽभिः ३. ६०, ६; ५. ८१, ४; ८. ५२, ३; ९. ७, ७; ८६, ५; ९; १०७, २४.
धर्मऽवंता ८. ३५, १३.
धर्मा ९. ९७, २३.
धर्माणः १०. २१, ३.
धर्माणं १. १८७, १; १०. ९२, २.
धर्माणि १. २२, १८; १६४, ४३; ५०; ३. ३, १; ५. २६, ६; ९. ६४, १; ९७, १२; १०. ९०, १६.
धवध्वै ५. ६०, ३.
धवंते ६. ४७, १४.
धवीयान् ६. १२, ५.
धाः ३. २८, ५; ३०, ३; ५. ३२, ५; ६. १९, १०.
धाः १. २६, १०; ४८, १२; ५४, ११²; ६१, १६; ६३, १; ७२, ७; १७१, ५; २. ४, ९; ३. ८, ३; १७, ५; २४, १; २९, ८; ३१, १९; ३६, १; १०; ५१, ६; ५६, ६; ४. ६, ११; १७, १८; ३२, १२; ५. ७, ९; ३६, ५; ७९, ६; ८३, ७; ६. ४, ४; १०, ६; १३, ५; ४०, १; ४७, ९; ३०; ७. २०, १०; २४, ५; ७७, ६; ७९, ५; ८. ९६, १६; ९. ८, ८; ९०, ६; १०. ४६, १०; ६९, ३.
धाक् १. १५८, ४.
धात् ३. ३१, १३; १०. १३२, ५.
धात् १. ६३, २; ६७, २; ७१, ५; १०७, ३; ३. ५४, १२; ४. १७, १३; २४, २; ५. ४१, १६; ४२, १६; ६. ३, ५; ४, २; १९, २; ३०, २; ४०, ४; ४९, ७; १४; ७. ३८, ३; १०. ३०, १२; ६८, १२.
धातं ३. ५४, १३; ६. ५०, ७; ७. ३९, ६.
धातु ४. ३५, ८; ६. ६५, ३.
धातः १०. १६७, ३.
धातः १०. १८, ५.
धातन ७. ४७, ४.
धातं १. १२०, ८; ७. ७१, ५; १०. ९३, १०.
धातवे १. १६४, ४९; ८. ७०, १५; १०. ११५, १.
धाता ९. ९७, ३८.
धाता १. १२३, ५; ७. ३५, ३; १०. ८२, २; ८५, ४७; १२८, ७; १५८, ३; १८४, १; १९०, ३.
धातारः ८. ७, ३५.
धाति २. ३८, १.
धाति ४. ५५, १; ७. ९०, ३.
धातु ५. ४४, ३; १०. ५६, २.
धातु १. १९०, ८; ६. ४७, ११; १०. ११, २.
धातुः १०. १८१, १.
धातृऽभिः ४. ७, १; ८. ९२, २९; ९. १०, ३.
धातृणां १०. १२८, ७.
धात्रा ९. ११३, ४.
धानं ३. ७, ६.
धानाः १. १६, २; ३. ३५, ३; ७; ५२, ५–८; ४. २४, ७; ६. २९, ४; १०. २८, १.
धानानां ८. ७०, १२.
धानाऽवंत् ३. ४३, ४.
धानाऽवंतं ३. ५२, १.
धांतु ९. ८, २; १०. ७४, ३.
धान्यऽकृतः १०. ९४, १३.
धान्यं ५. ५३, १३; ६. १३, ४.
धापय १०. १५१, ५.
धापयंते ५. ४७, ४.
धापयेते इति १. ९६, ५; ३. ५५, १२.
धापयेते इति १. ९५, १.
धाम १. ५७, ३; ९१, ३; ९५, ९; १२१, ६; १२३, ८; ९; १४४, १; १५२, ४; ५; १५३, २; २. ३, ११; ३. ७, ६; ४. ५, ४; ६. २, ९; २१, ३; ६७, ९; ७. ६१, ४; ६३, ३; ८७, २; ८. ४१, १०; ९. ६९, ६; ८६, १५; ९४, २; ९६, १८; १९; ९७, ५; ३१; ३२; १०९, ४; १०. १०, ६; ४५, २; ४८, ११; ६५, ५; ६७, २; ८९, ८; १२४, ३; १८१, २; १८९, ३.
धाम १. १२२, १२.
धामऽधाः ९. ८६, २८.
धामन् १. ४३, ९; ४. ७, ७; ५८, ११; ७. ३६, ५.
धामनि ८. १२, ३२.
धामनी इति ९. ६६, २.
धामऽभिः १. १४, १०; २२, १६; ८५, ११; ३. ३, ४; ३१, २१; ३७, ४; ४. ७, ५; ७. ६६, १८; ८. १९, १४; ९. ६६, ५; ६७, २६; १०२, २; १०. ९३, ६.
धामऽभ्यः ८. २७, १५; ९२, २४.
धामऽशः १. १६४, १५.
धामऽसाचं ३. ५१, २.
धामऽसु ८. १३, २०; ९. ८६, २२; १०. २५, २.
धामहे १. ९२, १३; ५. १६, ५; ९. ७४, ५.
धामानि १. ९१, ४; १९; २. ३, २; ३. ३, १०; ५५, १०; ४. ५५, २; ७. ६०, ३; ८. २१, ४; ४१, ७; १०१, ६; ९. २८, २; ५; ६३, १४; ६६, ३; ८६, ५; ११४, १; १०. १३, १; ५६, ५; ७०, ७; ८०, ४; ८१, ५; ८२, ३; ९७, १; २; १२२, ३.

धाम्नः १. ८७, ६; ७. ५८, १.
धाम्ना ९. ३९, १; १०. १६६, ४.
धाम्ने ५. ४८, १; ८. ६३, ११; ९२, २५; ९. २४, ५; १०. ७६, ८.
धार्यःऽभिः ६. ३, ८.
धार्यसा ७. ९५, १.
धार्यसे १. ३१, १३; ७२, ९; ९४, १२; १३०, २; १४१, ६; २. ५, ७; १७, २; ३. ३८, ३; ५०, ३; ५. ७, ६; ९; १५, ४; ७०, २; ९. ७०, ५; ८६, ३.
धार्यि १. १५८, ३; ५. ४४, ८; ७. ५, २; ८. ६३, १२; १०. ४६, १.
धायि १. १४१, १; १४५, ५; १७१, २; १९०, ८; ४. ७, १; २८, २; ३६, ७; ५. ४१, १५; ५६, ७; ६६, २; ६. २०, २; ५; २९, ५; ७. ४, ४; ८. ५०, ३; ७०, २; ९२, २९; १०. १०, ३; ९६, ४; ११५, २.
धायीः १. १४७, ५.
धायुः ३. ३०, ७.
धायू इति ७. ३६, ४.
धारऽपूताः २. २७, २; ९.
धारय १०. २५, ४.
धारय १. ३०, २२; ६. ८, ६; ८. १३, १२; ९५, ८; ९. १२, ९; ६३, १; ३०; १०. १९, ३; ५९, ५; ६०, ५; १२२, ८; १७३, २.
धारयः ९. २२, ७; १०७, २३; १०. ७३, ४.
धारयत् ७. ६४, ४; ८. ३२, २५; ७७, ६.
धारयत् १. १०३, २; २. १५, २; १०. ९२, १०.
धारयतं ५. २७, ६; १०. १९, १.
धारयतां १०. १७३, ५.
धारयति ७. ८५, ३.
धारयत्कवी इति धारयत्ऽकवी १. १६०, १.
धारयत्ऽक्षितिं १. १३६, ३.
धारयत्क्षिती इति धारयत्ऽक्षिती १०. १३२, २.
धारयथः ५. ६९, १.
धारयथाः ६. ३६, १.
धारयध्वं १०. ७०, ५.
धारयन् १. २२, १८; १०. ८१, ४.
धारयन् १. ९६, १–७; २. २७, ८.
धारयंत ७. ६६, २.
धारयंत २. २७, ९; ४. १, १८; ४२, २; ५. १५, २; २९, १.
धारयंतः २. २७, ४.
धारयंतं ७. १०४, १३.
धारयंतु १०. १८, १३.
धारयंते ८. ९४, २; १०. १२, ७.
धारयंते १०. १२, ३.
धारयं ४. ४२, ३; ४.
धारयं १०. ४८, ८; ४९, ९; १०.
धारया ३. ३६, ७; ८. ६, ८; ९. १, १; २, ९; ३, ७; १०; ५, १०; ६, १; ७; १०, ४; १२, ८; २३, १; २५, ६; २९, ४; ६; ३०, ३; ४; ३३, २; ३४, १; ३५, १; ४१, ६; ४२, २; ४४, २; ४५, ६; ४९, २–४; ५१, ५; ६१, ५; ६२, २२; ६३, ४; ७; १४; २१; २८; ६४, १३; ६५, १०; १२; ६६, ७; ६७, १३; ६८, ८; ७२, ५; ८४, ३; ९७, ११; ४५; १००, ५; ६; १०१, २; १०२, ३; १०७, ४; ८[2]; २५; १०८, ५.
धारयाते १०. १४४, ६.
धारयाम ४. ५८, २.
धारयिष्यति ४. ५४, ४.
धारयुः ९. ६७, १.
धारयेः ४. ४, ८.
धारयेथां ६. ७४, १.
धारयेथे इति ६. ६७, ६.
धारऽवाकेषु ५. ४४, ५.
धारा ३. ५७, ६; ६. ५५, ३; ९. २, ३; ७, २; १६, ७; ५८, १; ७५, ४; ८०, १; ८६, ४४; ८७, ८; ९८, ३; १००, ४; १११, १.
धाराः १. ८४, ४; ८५, ५; १२५, ४; २. ७, ३; ३. १, ८; ९; ४. ५८, ५; ७–१०; ५. १२, २; ३२, १; ८३, ६; ७. ४३, ४; ९. २९, १; ३०, १; ५६, २; ५७, १; ६२, ७; २८; ८६, ४७; ९६, २२; ९७, २९; ३१; ३३; १०६, १४.
धाराभिः ३. ४०, ६; ९. ५, ३; ६५, १४; ७३, २; ९३, ३; ९८, २; १०६, ७.
धारा १. ६७, ४; ६. ३, ५; ४७, १०; ८. ७३, ९; ९. १७, ८.
धाराऽवराः २. ३४, १.
धाव ९. ४९, ४; ८६, ४८; १०. २९, ३.
धावत ८. १, १७; २, २५; १००, ७; ९. ११, ५; ४६, ४; १०६, ९.
धावतः ८. ३१, ५.
धावतं १. १०९, ४; ५. ६४, ७.
धावंति ७. ३२, ६.
धावति ९. ३, २; ७; १४, ४; १७, ४; २८, १; ४; ३७, ३; ६; ५४, २; ५८, १; ६०, ३; ६७, १४; ७४, ९; ७५, ४; १००, ४; १०३, ६; १०६, १०.
धावतु ८. १७, ५; २२, ४; १०. १४५, ६[2].
धावते १. १०५, १; १४१, ५; ६. ४८, ६.
धावतऽभिः १. १०१, ६.
धावन् ६. १७, ११.
धावंति ९. २१, १; ६६, ६.
धावमानं ८. ३, २१.
धावयन् १०. १४६, २.
धावसि १०. ८६, २.
धावसि ९. १६, ८; ८६, ३४; ३८; ९७, ५५.
धासथ १. १११, २.
धासथः १. १६०, ५.
धासिः ९. ८५, ३.
धासिना ४. ३, ९; ६. ६७, ६.
धासिं १. ६२, ३; ४. ५५, ७; ५. १२, ४; ४१, १७; ७. ६, २; ८. ४३, ७; २९; १०. ३०, १.
धासिंऽइव १. १४०, १.
धासुः ७. ९७, ५.
धासेः १. १२२, १३; ३. ७, १; ३; ५७, १; १०. ८९, ११.

धितऽवानं ३. २७, २; ४०, ३.
धित्सथः १. ४६, ९.
धियः १. ३, १२; १४, २; ३४, ५; ६१, २; ९०, ५; ९४, ३; ४; ११२, २; ११७, २३; १३४, २²; १३५, ५; १४३, ६; १५१, ६; २. २१, ५; ३. ३४, ५; ६२, १०; ४. ४१, ८; ५०, ११; ५. ४७, ६; ७१, २; ८१, १; ६. २१, १; ३५, १; ३; ५३, ४; ६२, ३; ७. १०, १; २७, १; ६६, ३; ७९, ५; ८२, ३; ९४, २; ८. ३, १; १२; २१, ६; १२; २६, २५; ३५, १६; ४०, ९; ४६, ११; ६०, १२; ६३, १; ८४, ७; ९२, ११; ९. १९, २; २२, ३; ४७, ४; ७९, १; ८६, १७; ९४, १; २; ९९, २; १०८, १०; ११२, १; १०. ७, ४; ३९, २; १०१, २; १०६, १; १३३, ३; १३९, ५²; १४२, २; १४३, ३; १५६, १.
धियः १. २३, ३; ८७, ४; ४. ४१, ५; ६. १, १; ७. ३६, ८; ९. ७५, २; ९९, ६.
धियध्यै ७. ३४, २४.
धियं १. २, ७; ६१, १६; ८०, १६; ८८, ४; १०२, १; १०९, १; १४३, ७; १४४, १; २. ३, ८; ११, १२; २८, ५; ३४, ६; ३८, १०; ४०, ५; ६; ३. १८, ३; ५४, १७; ६२, ८; ५. ४५, ६; ११; ६. १४, १; ४७, १०; ४९, ७; ५२, १६; ५३, १०; ७. १, १०; ३४, ८; ९; ३६, ७; ४१, ३; ६७, ५; ८. ६, ४३; १३, २६; ४२, ३; ८६, २; ९५, ५; १०२, २२; ९. १००, ३; ११०, ७; १०. ४२, ७; ४६, ५; ६४, १२; ६७, १; ७४, ३; १०१, ९.
धियंऽजिन्वः ६. ५८, २.
धियंऽजिन्वं १. ८९, ५.
धियंऽजिन्वा १. १८२, १; ८. २६, ६.
धियंऽजिन्वासः ७. ३३, १.
धियंऽधाः १. ६७, २; ७२, २; ४. ४५, ७; ७. २, २; १०. ६१, १८.
धियंऽधियं १. १६८, १; ६. ४९, ८.
धियंऽधे ७. १३, १.
धियसानः ५. ३३, २.
धियसानस्य १०. ३२, १.
धिया १. २, ६; ३, २; ५; ४६, २; ८; ५२, ३; १३९, १; १४३, ६; १५९, १; २. ३१, ६; ३. २, १; ३, ६; ११, २; ३; १२, १; २७, ६; ९; ६०, २; ५; ६२, १२; ४. १, १०; १६, २१; ५. ४५, ११²; ६१, १५; ६. २, ४; २२, ७; ३८, ३; ७१, ६; ७. १, ५; ३७, ६; ८३, ८; ९४, ४; ८. १, १९; ३, १८; ४, १५; ६, २८; १३, ८; २४, ७; २६, १९; २७, ८; १३; ६१, १; ६६, ८; १४; ६९, १; ८७, ६; ९२, १५; ९३, १७; ९६, ११; १०३, ११; ९. १५, १; २५, २; २६, १; ४; ४४, २; ६४, १६; ६७, २७; ७१, ६; ७२, ४; ७४, ७; ७६, ३; ८६, १३; ९१, १; १०१, ३; १०. ११, १; २९, ४; ४०, १; ५३, ६; ७४, १; ९२, १२; १५०, ३; १७२, २; १७६, २.
धियाऽजुरः ५. ४३, १५.
धियां ५. ४४, १३.
धियाऽयुते १. १५५, १.
धियाऽयुते ९. १५, २.
धियाऽयवः १. ८, ६.
धियाऽवसुः १. ३, १०; ५८, ९; ६०, ५; ६१, १६; ६२, १३; ६३, ९; ६४, १५; ३. ३, २.
धियावसो इति धियाऽवसो ३. २८, १.
धिये १. २७, ११; १११, ४; ४. १, १८; २१, ७; ५. ४१, ६; ६. ५३, १.
धिरे १. १६६, १०; ८. २८, ५; ९. ६८, १.
धिषणा १. ९६, १; १०२, १; ७; १०९, ४; ३. ३१, १३; ३२, १४; ४. ३४, १; ५. ४१, ८; ६. ११, ३; १९, २; ७. ९०, ३; ८. १५, ७; १०. ३०, ६; ९६, १०.
धिषणाऽइव ३. ४९, ४.
धिषणानां ५. ६९, २.
धिषणाभ्यः ४. ३६, ८; ९. ५९, २.
धिषणां १. २२, १०; ३. २, १; १०. ३५, ७.
धिषणायाः १. १०९, ३; १०. १७, १२.
धिषणे ३. ५६, ६.
धिषणे इति १. १६०, १; ३. ४९, १; ६. ८, ३; ८. ६१, २; १०. ४४, ८.
धिषणे इति ६. ५०, ३; ७०, ३.
धिषण्यंतः ४. २१, ६.
धिषा १. १७३, ८; ४. २१, ६.
धिषे १. ५६, ६; ७०, ५; १०. २१, ३.
धिष्ण्यां १. ३, २; १८२, १; २; २. ४१, ९.
धिष्ण्या १. ८९, ४; ११७, १९; १८१, ३; ६. ६३, ६; ८. ५, १४; २६, १२.
धिष्ण्याः ३. २२, ३.
धिष्ण्यां १०. ११४, ९.
धिष्ण्यासु ४. ३, ६.
धिष्ण्ये इति ७. ७२, ३.
धिष्ण्यौ ७. ६७, १.
धिष्व २. ११, १८; ६. १८, ९; २२, ९; ४५, १८.
धिष्व १. ९१, १८; २. १८, ७; ३. ६, ६; ८. ३३, १५.
धीः १. ९५, ८; १८५, ८; २. २, ९; ३. ३९, २; ५. ४१, ५; ६. ३, ३; २३, ८; ८. ८०, ७; १०. ११, ४; ४२, ३.
धीऽजवः ९. ८६, १.
धीऽजवनः ९. ८८, ३.
धीऽजवनं ९. ९७, ४९.
धीऽजवना ८. ५, ३५.
धीऽजुवः ९. ८६, ४.
धीतं ८. ३, १६; ४०, ३.
धीतयः १. २५, १६; १३२, ५²; १३९, १²; १४४, ५; ३. १२, ७; ६. ३४, ३; ८. ६, ७; ८; ४४, २२; ४९, ६; ५०, ४; ९. ८, ४;

१५, ८; १९, ४; ६६, ११; ८६, ३१; ९३, १; ९९, ४; १११, २; १०. २५, ४; ६४, २.
धीतये १. ४१, ५.
धीता ८. ४१, १.
धीतानि ८. ८, १०.
धीतिः १. ६८, ३; ११०, १; ११९, २; ४. ५, ७; २३, ८; ८. १२, १०; १०. ३१, ३; १११, २.
धीतिऽभिः १. २२, १४; ११०, ४; १५३, १; १६१, ७; १६४, ३६; ३. १३, ५; ५२, ६; ४. ३६, ४; ५. ५३, ११; ६. १४, १; ६१, २; ७. १५, ९; ६६, १०; ८. ८, ५; १९; १२, ३१; ५४, १; ६०, ४; १०२, १६; ९. ९, ४; ४०, १; ६२, १७; ६८, ७; १०७, २४; १११, २; १०. २६, २; १४०, ३.
धीतिं १. ७१, ३; ७७, ४; १४३, १; २. ३१, ७; ६. १५, ९; ११; ३८, १; ७. १३, १; ६४, ४; ९. ७६, ४; ९७, ३४; १०. ८, ७.
धीती १. १६४, ८; ५. २५, ३.
धीनां १. १८, ७; ३. ३, ८; ४. १६, १८; ६. ४४, १५; ६१, ४; ८. २७, २; ९. १२, ७.
धीभिः १. १३९, २; २. ३, १०; ३. ३८, ५; ४. १, १४; ११, ५; ३७, ६; ५. २५, ४; ५२, १४; ६. १८, ६; ४५, १२; ५०, १०; १५; ७. २३, ४; ३५, ११; ३७, ५; ९३, ३; ८. ४, २०; ८, ७; ९, २१; १९, ९; १४; ३५, २; ४२, ४; ४३, १९; १०१, १६; १०३, ३; ९. १७, ७; ६३, २०; २१; ६६, ८; १०६, ११; १०. ६५, १३; १४; ६६, ५; ६७, ८; १०४, ३; ११०, २.
धीमहि १. १७, ६; ४४, ११; १२७, ५; १३१, २; १४१, १०; २. ११, १२; ३. २९, ४; ३०, १९; ६२, १०; ५. २१, १; ८२, १; ६; ७. १५, ७; ६६, ९; ८. ७, १८; २२, १८; १०३, ५; १०. १६, १२; ३५, ४; ३६, ५; ७; ६६, २; ८७, २२.
धीमहे २. २३, १०.
धीयते १. ८१, ३; ३. २७, ८; ९. ६२, १५; ६९, १; १०. १८९, ३.
धीर् १. ९४, ६.
धीरः १. ६२, १२; ६४, १; १३०, ६; १४५, २; १६०, ३; १६४, २१; २. ३८, ४; ४. ५६, ३; ५. २, ११; २९, १; १५; ६. ४७, ३; ७. ५६, ४; ८. ४४, २९; ४८, ४; ९. ८७, ३; ९२, ३; ९७, ३०; ४६; १०. ८२, १; ८९, ८; ११४, ९.
धीऽरणासः ३. ३४, ८.
धीरं १. १७९, ४; ८. ४२, २; १०. ८६, १९.
धीरस्य ९. ९३, १.
धीरा ७. ८६, १.
धीराऽइव ५. ५०, ४.
धीराः १. ६५, १; ६७, ५; ९१, १; ३. ८, ५; २६, ६; २८, ४; ३१, ५; ५६, १; ५. ४५, १०; ७. ३१, ११; ८. ५९, ६; ९. ७३, ३; ९; ९६, ११; ९७, ५७; १०. २५, ५; ४६, २; ७१, २; ९४, ४; १०१, ४; ११४, ७; १३०, ७.
धीरासः १. १४६, ४; ३. ८, ४; ४. ३३, ३; ३६, ७.
धीयौ २. २७, ११.
धीऽवतः ८. ९२, ११.
धीवतःऽधीवतः ६. ५५, ३.
धीऽवतः ७. ८३, ८.
धीऽवतं ८. २, ४०.
धीषु १. १७, ८; ७९, ७; ७. ६७, ६; ८. ७१, १२.
धुः २. २०, ८.
धुः २. ४, ३; ४. ३३, ११; ५. ५८, ७; ७. ३४, १८; ३६, ९; १०. ४६, ५; ४९, २.
धुक्षत ६. ४८, १२.
धुक्षत १. १६०, ३; ६. ४८, १३.
धुक्षन् १. १२१, ८.
धुक्षन् ८. १, १७.
धुक्षंत ८. ७, ३.
धुक्षस्व ८. १३, २५; ५४, ७; ९. ६१, १५.
धुक्ष्व ४. ५७, २.
धुनऽईतयः ४. ५०, २.
धुनयः १. ६४, ५; ८७, ३; २. ३०, २; ५. ६०, ७; ६. ६६, १०; ७. ५, ५; १०. ७८, ३; ९५, ३.
धुनयंत २. २५, ५.
धुनयंतां ३. ५५, १६.
धुनिः १. ७९, १; १७४, ९; ५. ३४, ५; ८; ७. ५६, ८; १०. ८९, ५.
धुनिं २. १५, ५; ९; ६. १८, ८; ७. १९, ४; १०. ११३, ९; १४९, १.
धुनिऽमतीः १. १७४, ९.
धुनिऽव्रतं ५. ५८, २.
धुनिऽव्रताय ५. ८७, १.
धुनी इति १०. २२, ४.
धुनीचुमुरी इति ६. २०, १३.
धुनीनां ५. ८७, ३; ८. २०, १४.
धुरः १०. ९४, ६; ७.
धुरः १०. १०२, १०.
धुरं ५. ४३, ८; ८. ३, २३; ४८, २; ९. ४५, ४; १०. २६, ८.
धुरा १. १६४, १९.
धुरि १. ८४, १६; १३१, २; १३४, ३[२]; १५१, ४; १६२, २१; १६४, ९; २. १८, ७; ३. ६, ६; ४. २९, ४; ५. ४६, १; ५६, ६[२]; ५८, ७.
धुरिऽइव ७. २४, ५.
धुरिति धुः ७. ८५, ३; १०. ७४, १.
धुरिति धुः १. ७३, ७; ३. ३८, ३; ४. ६, ९; ५. ४१, ६; ७. ४०, ४.
धुरौ १०. १०१, १०; ११.
धूः ८. ३३, १८; १०. २८, ५; ६.
धूःऽसदः २. ३४, ४.
धूःऽसदं १. १४३, ७; २. २, १; १०. १३२, ७.
धूःऽसु १. १००, १६; ३. ३५, २; ५. ५५, ६; ७. ३४, ४; ६३, २;

६७, ८; १०. ५०, २; ७७, ५; १०५, ९; ११४, १०; १७५, १.
धूतः ८. २, २; ९. ६२, ५; १०७, ५.
धूतयः १. ६४, ५; ८७, ३; १६८, २; ५. ६१, १४.
धूतयः १. ३७, ६; ३९, १; १०; ५. ५४, ४; ६. ४८, २०; ७. ५८, ४; ८. २०, १६.
धूतस्य १०. १०४, २.
धूनवत् ९. ९७, ५३.
धूनुत १०. ६६, १४.
धूनुते ८. ३४, ३.
धूनुथ १. ३७, ६; ५. ५७, ३.
धूनुथ ५. ५४, १२.
धूनुषे १०. १३४, ४.
धूनुहि १. १०, ८; ३. ४५, ४; १०. १३४, ३.
धूनोति १०. २३, ४.
धूमः ५. ११, ३; ६. २, ६; ७. ३, ३.
धूमऽकेतवः ८. ४३, ४.
धूमऽकेतुः १. २७, ११; १०. ४, ५; १२, २.
धूमऽकेतुना १. ९४, १०.
धूमऽकेतुं १. ४४, ३; ८. ४४, १०.
धूमऽगंधिः १. १६२, १५.
धूमं १. ३६, ९; १६४, ४३; ३. २९, ९; ४. ६, २; ७. २, १; १०. ४५, ७.
धूमासः ७. १६, ३.
धूमिनः ५. ९, ५.
धूमेन ६. ४८, ६.
धूर्तयः ८. ४५, ९.
धूर्तिः १. १८, ३; ८. २७, १५; ४८, ३.
धूर्तेः १. ३६, १५; १२८, ७²; ७. १, १३.
धूर्वणे ९. ६१, ३०.
धूर्वंत १०. ८७, १२.
धूर्वति ८. ४५, ९.
धूर्वतु ६. ७५, १९.
धृतऽदक्षं १०. ४१, ३.
धृतऽदक्षा ५. ६२, ५.
धृतऽव्रतः १. २५, ८; १०; ४४, १४; १४१, ९; २. १, ४; ४. ५३, ४; ६. १९, ५; ८. ९७, ११; १०. ६६, ५.
धृतऽव्रता ८. २५, २; ८.
धृतऽव्रता १. १५, ६; ६. ६८, १०.
धृतऽव्रताः २. २९, १; १०. ६६, ८.
धृतऽव्रताय १. २५, ६; ८. ४४, २५.
धृतऽव्रते ८. २७, ३.
धृषऽजः ५. १९, ५.
धृषत् १. ५४, ३; ४; ५. ३५, ४; ६. ४२, ३; ४५, २१; ४७, ६; ८. २१, २; ३२, ४; ३३, ३; ४९, ४; ६२, ५.
धृषतः १. ५४, ३; ८. ६२, ५.
धृषता १. ५४, ४; ७१, ५; १६७, ९; १७४, ४; २. ३०, ४; ४. ४, २; ५, ६; २२, ५; ६. ६, ३; ६; १८, १३; २२, ६; ७. १९, ३; ८. २४, ४; ८१, ७; ८९, ४; १०. १११, ६; ११५, ६.
धृषती २. ३०, ८.
धृषत्ऽमनः १. ५२, १२; ८. ८९, ४.
धृषत्ऽवर्णं १०. ८७, २२.
धृषत्ऽविनः ५. ५२, २.
धृषमाणः १. ५२, ५.
धृषितः ८. ३३, ६; ९६, १७; १०. ११३, ५; १३८, ४.
धृषिता ८. ५२, ३.
धृषिताः १०. ८४, १.
धृषितेषु १०. ३८, १.
धृष्णवः १. ९२, १.
धृष्णवः ५. ५२, १४.
धृष्णवे १. ८१, ३; २. १६, ४; ८. २४, १; ९. ९९, १.
धृष्णु ३. ३६, ४; ६. ६६, ५; ८. ६९, ८; १०. ३४, १४; ४९, २.
धृष्णुऽओजसः २. ३४, १.
धृष्णुऽओजसं ८. ७०, ३.
धृष्णुः १. ६३, ३; ६. २५, ५; २९, ३; ७. २०, ५; ९. ४७, २; १०. १६, ७; ६९, ५.
धृष्णुना १. ५४, २; ५६, ४; १६७, ९; १०. १०३, २.
धृष्णुं ६. ६७, ११.
धृष्णुऽया १. २३, ११; ४६, ५; ५३, ७; ४. २१, ४; ३०, १३; ३१, १४; ५. १०, ५; ५२, १; २; ४; ६. १६, २२; ४६, २; १०; ८. ४९, २; १०. १०२, १.
धृष्णुऽसेनः ३. ५४, १५.
धृष्णुऽसेनाः ६. ६६, ६.
धृष्णुहि १. ८०, ३.
धृष्णू इति १. ६, २.
धृष्णो इति १. ३०, १४; ८४, १; २. ३७, ३; ३. ५२, ८; ४. १६, ७; २२, ५; ६. १७, १; २१, ७; ३७, ४; ७. १९, ३; ८. २४, ४; ३३, ३; ४५, १४; ७३, १८; ७८, ३; ८१, ७; ९. १०८, ६; १०. १११, ६; १२०, ४.
धृष्णोः ७. ५६, ८; १०. २२, ३.
धेतन ८. ६७, ५; १०. ३७, १२.
धेथे इति १. १५८, २.
धेनवः १. ३२, २; ७३, ६; ८४, ११; १२०, ८; १२५, ४; १३४, ६; १३५, ८²; १५१, ५; १५२, ६; १७३, १; २. २, २; ५, ५; ३. १, ७; ७, २; ४५, ३; ५५, १६; ५७, ३; ४. २२, ६; ५. ६, १; २; ४३, १; ५३, ७; ५५, ५; ६९, २; ६. ४५, २८; ७. ३२, २२; ३६, ३; ४२, १; ८. ४, ८; ४९, ५; ७०, ४; ८८, १; ९. १, ९; १३, ७; ३३, ४; ६६, ६; १२; ६८, १; ६९, ४; ७०, १; ७७, १; ८६, १७; २५; ९७, ३५; १००, ७; १०. ३२, ४; ७५, ४; ९५, ६; ९६, २.
धेनवे ८. ४७, १२.
धेना १. २, ३; १०. १०४, १०.
धेनाः १. १४१, १; ३. १, ९; ३४, ३; ४. ५८, ६; ५. ६२, २; ७. २१, ३; ९४, ४; ८. ३२, २२; १०. ४३, ६.
धेनाभिः १०. १०४, ३.
धेना १. ५५, ४.
धेनु ६. ६६, १.

धेनुः १. ३२, ९; ६६, १; १३४, ४; १५३, ३; १६१, ३; १८६, ४; २. १६, ८; ३४, ८; ३५, ७; ३. ५५, १३; ५८, १; ५. ४४, १३; ७. २, ६; ८. १४, ३; १००, ११; ९. ८६, २; १०. ५, ७; ६१, १९; ६९, ८.
धेनुःऽइव ४. ५७, २; ८. २२, ४.
धेनुऽभिः २. ३४, ५; ४. २४, १०; ८. २, ६; ९. ६१, २१; ७२, १.
धेनुं १. २०, ३; ९१, २०; ११२, ३; ११८, ८; १३७, ३; १३९, ७; १६०, ३; १६४, २६; २. ३२, ३; ३४, ६; ३. ५७, १; ४. ३३, १; ८; ३४, ९; ४२, १०; ६. ३५, ४; ४८, ११; १३; ६३, ८; ७. १८, ४; ८. १, १०; १०. ३९, १३; ६१, १७; ६४, १२; १७६, १.
धेनुऽमतीं ८. ३१, ४.
धेनुमती इति धेनुऽमतीं ७. ९९, ३.
धेनुऽमत्यै १. १२०, ९.
धेनुंऽइव ५. १, १.
धेनू इति १. १४६, ३; ३. ६, ४; ५५, १२; ४. २३, १०.
धेनूः ८. ३५, १८; ९. ३४, ६; ९७, ५०.
धेनूःऽइव १. १३०, ५.
धेनूनां ५. ६१, १०; ८. ६९, २; १०. २२, १३.
धेने इति १. १०१, १०; ५. ३०, ९.
धेनोः ३. ३८, ७; ४. १, ६; १६; ४१, ५; ६. ३५, ५.
धेयां ५. ६४, ४; १०. ५२, ५.
धेयुः ३. ५०, २.
धेष्ठः १. १७०, ५.
धेष्ठा ४. ४१, ३; ७. ९३, १.
धेहि ८. ९६, १०.
धेहि १. ९, ७; ८; २८, ९; ४३, ७; ४४, २; ७९, ४; ९; १२३, १३; २. २१, ६; २३, १५; ३०, ९; ३. १, २२; २, ६; १८, ४; १९, ५; २१, १; २; ५३, १८; १९; ४. १७, २०; ५. ४, ७; १०; ३१, १३; ६. १, १२; ७, ३; ८, ५; १०, ५; १७, १४; १९, ९; ३५, २; ४; ४४, ९; ४७, ६; ६५, ६; ७. ११, ५; २५, ३; ७५, २; ८; ८. ९७, २; ३; ९. १९, ६; ३२, ६; ११३, ७; १०. ७, १; १४, ११; १७, ८; ९; २४, २; ३७, १०; ४२, ७; ५९, ६; ८३, ४; ८५, ४५; ८७, ३^{२}; १२; ९१, १५; ९८, ३; ११; १५८, ४; १८४, २^{२}.
धैर्थे इति ६. ६७, ७.
धौतरीभिः ६. ४४, ७.
धौतीनां २. १३, ५.
ध्मातः ७. ८९, २.
ध्मातरि ५. ९, ५.
ध्माताऽइव ५. ९, ५.
ध्यया ४. ३६, २.
ध्रजंतः १. १६५, २; ४. ४०, ३; ७. ३६, ३.
ध्रजंतं १. १४९, १; ४. ३८, ३.
ध्रजसा ६. ३, ७.
ध्रजीमान् १. ७९, १; १६३, ११.
ध्रांजिः १. १६४, ४४.
ध्राजिं १०. १३६, २.
ध्राज्या १०. ९७, १३.
ध्रियते ५. ३४, ७.
ध्रुतिः ७. ८६, ६.
ध्रुवः ३. ६, ४; ४. २, ७; ६. ९, ४; ९. १०२, ४; १०. १७३, १; २; ४.
ध्रुवऽक्षेमा ५. ७२, २.
ध्रुवऽक्षेमाः ४. १३, ३.
ध्रुवऽक्षेमासः ३. ५४, २०.
ध्रुवऽच्युत १. ६४, ११.
ध्रुवं १. १६४, ३०; ३. २९, १६^{२}; ५४, ८; ५. ६२, १; ६. ९, ५; १५, ७; ७. ७४, ५; ८२, ६; ८. ४१, ९; ९. २०, ४; १०. १७३, ३; ४; ५^{४}; ६.
ध्रुवयः ७. ३५, ८.
ध्रुवसे ७. ७०, १.
ध्रुवस्य १. १४६, १; ९. ८६, ६; १०. ५, ३.
ध्रुवा १. ३६, ५; २. ५, ४; ८. १७, १४; १०. १७३, ४^{२}.
ध्रुवाः ९. १०९, १२; १०. ९४, १२.
ध्रुवाणि १. १६७, ८; ३. ५६, १; ४. ५, ४; ५. ६९, ४.
ध्रुवासः १. ५९, ३; ६. ५२, ४; ७. १००, ४; १०. १७३, ४.
ध्रुवासु १. ७३, ४; ७. ८८, ७.
ध्रुवे १. २२, १४; २. ४१, ५; ३. ५४, ७; ९. ४०, २.
ध्रुवेण १०. १७३, ३; ६.
ध्रुवेभिः १. ८४, १८.
ध्वजेषु ७. ८५, २; १०. १०३, ११.
ध्वनयीत् १. १६२, १५.
ध्वन्यस्य ५. ३३, १०.
ध्वरसः २. २३, ५.
ध्वरसे ४. २३, ७.
ध्वसनौ १. १६४, २९.
ध्वसंति १. ११२, २३.
ध्वसयः १०. ७३, ६.
ध्वसयंतः १. १४०, ५.
ध्वसयंतं १. १४०, ३.
ध्वसिराः ७. ८३, ३.
ध्वस्मन्ऽवत् ६. १५, १२.
ध्वस्मा ८. ६६, १५.
ध्वस्मानः ४. ६, ६.
ध्वस्रयोः ९. ५८, ३.
ध्वस्रा १०. ४०, ३.
ध्वस्राः ४. १९, ७.
ध्वांतं १०. ७३, ११; ११३, ७.
ध्वांतात् १०. ७३, २.

न

न १. ५, ४; ७, ७; ८, ५; ७; ११, ३; १६, ५; १८, ४; ७; १९, २; २३, १५; २४, ६^{३}; २५, ३; ४; ६; १४^{३}; १६; २७, १; ३०, २; ३; १४; १५; २१; ३२, ४; ६; ८; ९; १३^{३}; १४; १५; ३३, २; ६; ८; १०^{९}; ३५, ६; ३६, २०; ३७, ६; ३८, १; २^{२}; ५; ८; १३; ३९, ४; ९; १०; ४०, ८; ४१, ४; ९; ४२, ८; १०; ४८, ३; ६; ५१, १; १४; ५२, १; २; ४; ७; १४^{३}; ५३, १; ५४, १; ५५, १; २; ३; ७; ८; ५६, १; २^{२}; ३; ४;

५७, २; ३; ५८, २[२]; ३; ५; ६[२]; ५९, ३; ४; ६०, ५; ६१, १; ४; ८; १०; १२; ६२, ७; १०; ११; १२[२]; ६३, १; ७; ८[२]; ६४, १; २; ६; ७; ९[२]; ११; ६५, १; २; ३[६]; ४; ५[२]; ६६, १[६]; २[४]; ३[२]; ४; ५[२]; ६७, १[२]; ३; ६९, १[२]–३[२]; ५; ७०, २; ५; ६; ७१, १[२]; ४; ७[२]; ९; १०; ७२, २; १०; ७३, १[२]; २[२]; ३[३]; ७४, ७; ७७, ३; ७९, १; २; ८०, ३; १२; ८१, ५[२]; ८३, २; ८४, १; १९; ८५, १; ७; ८[२]; ८८, १–३; ५; ६; ९१, ३; ६; ८; १३; ९२, ३–६; १२[२]; ९४, २; ९५, ६[२]; १००, ३; ५; १२; १३; १५[२]; १०२, १०; १०४, १; ५; १०५, १; ७; ८; १६[२]; १०६, १–६; १०९, १; ११२, २; १७; ११३, ३; ११५, २; ११६, ३; ९; १२; २३; ११७, ४[२]; ५[३]; ११८, ४; ११९, ७; १२०, ४; ५[२]; १२१, ६; १३; १२२, २; ९; १५; १२३, ९; ११; १२४, ३; ४[२]; ६[४]; १२७, १; ३[३]; ५; ६[२]; ८; ९[२]; १०[२]; ११; १२८, २; ५[२]; ६[२]; ७; १२९, १; २; ५; ६; ८[२]; १०; १३०, १[२]; २[३]; ३; ६; ८; १३१, २[२]; ७; १३२, ५; १३३, ६; १३५, ५; ८[२]; १३६, १; १३७, ३; १३८, १[२]; २[२]; ४; १३९, १; १४०, ६[२]; १४१, ७–१०; ११[२]; १३; १४३, ३; ४; ५[२]; ७; १४४, ३[२]; ४; १४५, २[३]; १४७, ३; १४८, १–४; ५[३]; १४९, २; ३[२]; १५१, १; २; ४; ८; ९[४]; १५२, ४; १५३, १–३; १५४, २; १५५, ६; १५६, १; १५८, ३; ५; १६१, १; ११; १६२, २१[२]; १६४, ६; १०; १३[२]; १६; १९; २२[२]; ३२; ३७–३९; ४४; ४५; ४८[२]; १६५, ९[२]; १४; १६६, २[२]; १०; १६७, ३[२]; ४; ५; ९; १६८, २[३]; ३[२]; ५[२]; ७[२]; १६९, ३; ४; ६; ७; १७०, १; ३; १७३, २; ३; ६[२]; ९[२]; १०[२]; ११[२]; १७४, ३; ८; ९; १७५, ३; ६; १७६, १; २; ४; ६; १७८, २; १७९, ३; १८०, ३–५; ६[२]; ९; १८१, ३; ६; ८; ९; १८३, १; ५; १८५, २; १८६, २; ५; ७[२]; ८[२]; ९; १८७, ११; १८९, ७; १९०, २; ३; ४[२]; ५; ६[२]; ७[२]; १९१, १; १०–१२; **२.** २, २–५; ७[२]; ८; १०; ४, ३–५; ६[२]; ७[२]; ८, ३; ४; ९, ५; १०, ५; ११, १; ३; २०; १२, ५; ९; १०; १३, ५; १४, ३[२]; ११; १६, ३[२]; ७[२]; ८[२]; १८, ८; १९, २; ७; ८; २०, १; २३, ४; ५[४]; १६; २५, ३[२]; २७, ११[४]; १३; २८, २; ४[२]; ८; ३०, १; ७[४]; ३१, १; ७; ३३, ९–११; १५[२]; ३४, १[२]; २[२]; ४–६; ८; १२–१४; ३५, ६[२]; ३८, ९[४]; ४१, ८[२]; ११; **३.** १, ४; ९; १२; १४; २, १[२]; ३; ७; १०; ११; १४; १५; ३, १; ९, २; १०, ५; १५, ५; २२, १; २६, ३; ५; २७, १४; २८, ४; २९, ६[२]; १४; ३०, २; १२; ३१, २; ३२, ७; ८; ९[३]; ११; १६[२]; ३३, ४; ३५, १; ३६, ४; ३८, १; ४१, ५; ६; ४५, १; ४; ४६, ५; ४९, ३[२]; ४; ५३, २; १४[२]; २३[२]; २४[२]; ५४, ८; १४; २१; ५६, १[४]; ५७, २; ५८, ४; ५९, २[४]; ६०, ४; ६२, १; **४.** १, ३; ६; १९[२]; २, ८; ९[२]; १४; १७; ३, १२; ४, १; ४; ५, १; ३; ५[२]; ६; १२; १३; १५; ६, ३–५; ६[२]; ७[३]; ८[२]; १०[२]; ७, ११; १०, १[२]; ३–५; ६[२]; १३, २; ५; १५, ६[२]; ७; १६, २; ३; ११; १३; १४[२]; १५[२]; १९–२१; १७, ४; १२; १५; १६; १९; १८, २; ३[२]; १३; १९, २; ४; ५; ७; २०, ५[३]; ६[२]; ७[२]; २१, १; २; ९; २२, ८[२]; २३, ६; २४, ९; २५, ५[२]; ६[३]; ७; २७, २; ४; २८, ३; ३०, १; १९; ३१, ४; ९; ३२, ८; ३३, १०; ११; ३४, ११[२]; ३८, २; ३; ५[२]; ६; ३९, २; ४०, ३; ४१, १; ८[२]; ४२, ८; ४३, ३; ४५, २; ४; ४७, २; ४८, १; ५१, ६; ८; ५२, ५; ५४, ४; ५८, ५–७; **५.** २, १[२]; ४[२]; ५; १०; ११; ३, २; ५[२]; १२[२]; ४, ९; ७, ७; ८, ५; ९, ४; ६; १०, २; ५[२]; १२, १; २[२]; ३; १५, ३; ५; १६, १; २; ४; १७, ३; १९, ३; ४[२]; ५; २०, २; २९, ८; १४; १५; ३०, १४; ३३, ३; ५; ९; १०; ३४, ४[२]; ५[२]; ३६, १; २[२]; ३; ३७, ४; ४१, १; ४; ९; १०; १२; ४२, २; ६[३]; ४३, ७[३]; ८[२]; १४; ४४, २; ९[२]; १३; ४५, २; १०; ४६, १[२]; ४८, ५; ५१, ७; ५२, ३; १२; १४; १५; ५३, १६; ५४, ४; ५[२]; ७[७]; ८; १०; १३; १५; ५५, ५; ७[२]; ५६, ३; ४; ५७, १; ५९, २–४; ७; ६१, ३; १८; ६२, ९; ६३, ५; ६४, ७; ६६, २; ६९, ४; ७४, ५; ७६, २; ३; ७७, २; ७९, ९; १०; ८०, ५; ८२, २; ८४, २; ८५, ३; ६; ८[२]; ८६, ६; ८७, २[२]; ३[२]; ५; ६; ८; ९; **६.** २, १[२]; ४; ६; ७; ८[२]; ९; ३, २[२]; ३[२]; ४[३]; ५[२]; ६; ७[२]; ८[२]; ४, २; ३[२]; ५[२]; ६[२]; ७; ६, ५; ७, ४; ८, ५; ९, १; २[३]; १०, २; ११, १; ४–६; १२, १; २; ३[२]; ४[२]; ५; १३, १; २; १५, २; ४; ५[३]; १६, ३९; ४०[२]; १८, ३; ८[२]; १०[२]; १२[३]; १९, ५; २०, १; २; ४; ६–८; २१, ३; १०; २२, ११[२]; २३, ९; २४, ३; ४; ६[२]; ७[२]; ८[३]; २५, ५[३]; २७, ३[२]; २८, २; ३[३]; ४[२]; २९, ३; ५; ३०, ३; ४[२]; ३४, २; ३[२]; ४; ३५, ३; ३६, ३; ५; ४१, १; ४४, ३[२]; ६; २०; ४५, ३; ७; २२; २३; २५; २८; ३१; ४६, २; १४; ४७, १; ३; १०; १४[२]; ४८, १; १४[३]; १५; २१; २२; ४९, १२; ५०, ८; १०; ५१, १; ५२, १[४]; ५३, १; ५४, ३[२]; ४; ९; ५६, १;

५९, ४; ६०, ४; ६१, ५; ६३,
१; २^{२}; ६४, १; ३; ६६, २; ४;
५^{२}; ६; १०^{२}; ११; ६७, ४; ७;
९^{२}; ६८, ८; ९; ६९, ८^{२}; **७.** १,
५; २, ५^{२}; ३, २; ४; ५; ६^{२}; ४,
७; ५, ७; ७, १; ३; ८, ४; १०,
१; २^{२}; ११, १; १३, १; ३; १८,
४; ९–११; १५; २०^{२}; २१; २४;
२५; १९, १; २०, ६; २१, ३;
५^{२}; ६^{२}; २२, १; ५^{२}; ८^{२}; २३,
४^{२}; २४, ५; २५, ४; २६, १^{२};
२; २७, २; २८, ३; ३०, ३; ३१,
११; ३२, २^{२}; ३; ९; १०; १२^{२};
१८; २१^{२}; २३^{४}; ३३, १; ४; ८;
३४, १; ४; ७^{२}; १९; ३६, २; ३;
८; ३७, ३; ४; ४०, ३; ४३,
१–३; ४७, ३; ४८, १; ५६, १३;
१६^{४}; ५७, ३; ५८, ३; ५९, ७;
६१, २; ५^{३}; ६३, ३; ५; ६४, ५;
६५, ३; ६७, १^{२}; ८; ६८, ८;
७०, १^{२}; २; ७६, ३; ५^{२}; ७७, १;
७९, २; ८१, ३; ४; ८२, ७; ८३,
७; ८५, १; ८६, ५^{२}; ६; ७; ८७,
१; २; ४; ६; ८९, २; ९०, ७;
९१, २; ९३, ३; ९५, ५; ९७,
६; ९९, १; २^{२}; १०३, २^{२}; ३;
७^{२}; ८; ९; १०४, ३; १३^{२}; **८.** १,
२; ५^{३}; १३; १९; २०^{२}; २३; २७^{२};
२, २; ५^{३}; ६; १२^{२}; १४; १७;
. १८; २२; २६; २८; ३, १०; १८;
२३; ४, ८; १०; १७; ५, ३४;
३९; ६, ७; १२; १५^{२}; २३; २५;
३४; ३८; ७, १९; २६; ३६; ९,
६; ८; १९; ११, ४; १२, ४; ६;
७; १३; १५; २४^{२}; १३, ८; १४,
४^{२}; ९; १५, ११; १६, २; १९,
६^{२}; ८^{२}; २६^{५}; २७; ३३; २०,
१०; १३^{२}; १४; २०; २१, १;
१६; २३, ८; १५; २४, ५^{३}; १५^{२};
१७; २१^{२}; २५, २; १५; १९; २६,
२४; २७, ९; १५; २२; ३०, १;
३१, ६; ७^{२}; १४; १६^{३}; १७^{२};
३२, ४; ५; १५; १६^{२}; २३; ३३,
१; ८; ९; १३; ३४, ३; ५; ३७,

६; ३९, ३; ४१, ६; १०; ४३, ७;
२५^{२}; ३२; ३३; ४४, २९; ४५,
५; ९; २०; २९; ४६, २९; ३०;
४७, १; ३; ७^{२}; १२^{२}; ४८, ५;
६; १०; ४९, ३; ५; ६^{२}; ५०, २;
३; ५; ५१, ३^{२}; ७; ५५, २^{२}; ४;
५; ५६, १; ४; ६०, १३; ६१,
११^{२}; ६२, १२; ६३, २; ९; ६६, १;
२^{२}; ९; ११; ६७, १९; ६८, ८;
१९; ६९, ८; १५; ७०, २; ३;
५^{२}; ७; १२; १५; ७१, ४; ७२,
५; १४; ७३, १८; ७४, २; १०;
१४; १५; ७५, ८; ९; ७६, १;
७८, ४^{३}; ५; ८१, ३^{२}; ४; ८३,
३; ५; ८४, १; ८७, १; ८८, १;
२; ३; ५; ८९, ७; ९१, ३; ९२,
१२; १४; ९३, ५; ९; ११^{२}; ९५,
१; ९६, २^{२}; ११; १४; २१; ९७,
९^{३}; १५; ९८, ४; ८; ९९, ३;
४; ६; १००, ३; ७; १०१, २;
४^{२}; १०२, १२; १९; १०३, २;
६; ७; ११; **९.** २, ६; ५, ६;
६, ४; १०, १; ३^{२}; १२, २; १३,
६; ७; १४, ५^{२}; १६, १; ६; ७;
१७, ५^{२}; २०, ७; २१, ४; ६;
२२, ४; २४, २; ३२, ३; ४; ३३,
१; ३८, ४^{२}; ४१, १; ५; ४३, ५;
४४, १; ४५, ४; ५२, ३^{२}; ५३,
३; ५४, ३; ५५, ४; ५६, ३;
५७, १; ३; ६१, १६; २१^{२}; २७;
६२, ४; ६; १९; २८; ६३, १३;
१९; ६४, ३; ७; ९; ६५, १८;
१९; २६; ६६, १०; १२; २२;
६७, ११; १२; १५; ६८, १; ६९,
१^{२}; ३; ४; ६; ७०, ६; १०^{२}; ७१,
५; ६^{२}; ७; ७२, १; ५; ७३, ४;
६; ८; ७४, १; ७६, १–३; ७७,
३; ५; ७९, ३; ८०, १; ८१, २;
८२, १; २; ८३, १; ८४, २;
८६, २; ३; ९; १६; २६; ३४;
३५; ४४^{३}; ८७, १; ५; ७^{३}; ८८,
२; ३; ४^{२}–६^{२}; ७^{३}; ८९, १; ९०,
१; २; ९२, १; ६^{२}; ९३, १; २^{२};
३; ९४, १^{२}; २; ३; ९५, ४; ९६,

७; ९; १५^{२}; २०^{२}; २२; २३^{२};
९७, ९; १८^{२}; २०; २६; २८^{२};
३०^{३}; ३८^{२}; ४५^{२}; ४६; ४८; ५२;
५३; ५७; ९८, २; ३; ८; ९९,
५; ६; १००, १; ३; ७; १०१,
२; १२; १३^{२}; १४^{३}; १५; १०३,
१; ६; १०४, १; २; १०६, १२;
१०७, ९–११; १२^{२}; १३; २६;
१०८, २; ७; १०; १०९, १०;
११०, ५^{२}; ६; ९; १०; १११, १;
२; **१०.** १, ७; २, ५; ३, ४; ५;
४, ३–६; ६, २; ५; ६; १०, २;
४; ८^{२}; १२^{२}; १३; १२, ५; ८;
१३, ४; १४, २; १५, १३^{२}; १६,
७; १८, ५; २१, १; २२, १; २;
५; १३; २३, ६; २५, १; २६, ३;
२७, ३; ५^{२}; ७; २४; २८, १;
१०; २९, १; ४; ५; ८; ३०, १;
५; १०; ३१, ३; ८^{२}; ९^{३}; ३२,
४; ३३, २; ६; ९; ३४, २^{२}; ३^{२};
४; ५; ८; १२; ३५, १४; ३७,
३; ३९, १; २; १०; ११^{२}; १४^{३};
४०, २; ६^{२}; ११; ४२, २; ४; ५;
८; ९; ४३, १; २; ४; ५^{४}; ७^{२};
८; ९; ४४, ६; ४६, २; ५; ७;
४८, १; ५^{३}; ७; ८; ११; ४९, ३;
४; १०; ५१, ४^{२}; ६; ७; ५४, २;
५५, ६; ५६, ७; ५९, ३^{२}; ६०,
८; ६१, २–४; ८^{३}; ९^{२}; ११; १४;
१६; २०; ६२, ९; ६४, २; ६५,
५; ६८, १^{२}; २; ६; ८^{२}; ९; ११;
७१, ४^{२}; ५; ६; ९^{४}; ७४, २; ७५,
३; ४; ७; ७६, २; ७; ७७, १^{४};
२^{३}; ३^{४}; ४^{३}; ५^{४}; ७; ७८, १^{४}–७^{४};
७९, ३^{२}; ४; ८२, ४; ७; ८५, ३;
४; २५; ३४; ८६, १; ५; ६^{४};
१२; १५; ८७, १९; ८८, १८;
१९; ८९, २; ३; ५; ६^{४}; ७^{२}; ८^{२};
१२; १४; ९१, २; ५; ८; ९२, २;
९३, १; ८; ९; १२^{२}; १३; ९४,
१०; १२–१४; ९५, १; ३^{४}; ६^{३};
८^{२}; ९^{३}; १०–१३; १५; ९६, १;
२; ४^{२}; १०; ९७, १७; ९९, २;
८; १०; १००, ७^{२}; १०२, १०^{२};

१०३, १; १०५, २; ३; ५–८; १०६, ७^{२}; ८; ११; १०७, ३; ८^{४}; १०८, ४; ६; १०; १०९, ३; ५; ११०, ५; १११, ७; ९; ११२, ४; ९; ११३, ८; ११५, १; २; ३^{२}; ४^{२}; ७^{२}; ११७, १^{२}; २; ४^{२}; ६; ९^{४}; १२२, १; १२३, १; १२४, ७; ८; १२६, १^{२}; १२७, ४; ८; १२९, १^{२}; २^{४}; ७^{२}; १३०, ७; १३१, २; ३; १३२, ४; ६; ७; १३४, ४; १३९, ३; १४३, १^{२}; २^{२}; ३; ६; १४४, १; २; १४६, १^{२}; ५^{२}; १४७, ५^{२}; १४८, २; ५; १५२, १^{२}; १६०, ३; ४; १६५, ३; १६८, २–४; १७२, ३; १७६, १; ३; १७८, २; ३^{२}; १७९, २; १८५, २.

नऽईव १. १६१, ८.

नंशि ६. ५१, १२.

नंसंते ७. ५८, ५.

नंसै १. १२२, ५; १२.

न॒ंसै॒ ३. ३३, १०.

न॒ः १. १, ९; २, ९; ३, ६; १०; ४, २; ३; ५; ६; ५, ३^{२}; १०; ७, ४; ६; १०, ३; ४–६; ११; १२, १०^{२}; ११; १२; १३, १; २; ७; ८; १४, ११; १५, ३; ८; १०; १६, ४; ५; १७, १; १८, २; ३^{२}; २०, ७; २२, ८; ११; १३^{२}; १५; १६; २३, ६; ९; १२^{२}; १७; १८; २४, १; २; ११; २५, २; १२^{२}; २१; २६, १; २; ४; ५; ७–९; २७, २; ३; ५; ११; १२; २८, ८; २९, १–७; ३०, ४; ६; ८; १३; १६^{२}; ३१, ८^{२}; ९; १०; १२; १८; ३३, १; ३४, १; ५^{२}; ६; ७; १२^{२}; ३५, ११^{२}; ३६, २; ६; १२; १३; १४^{२}; १५; ३८, ६; ३९, ७–९; ४०, ३; ४२, १; २; ६; ७^{२}; ४३, २; ३; ६; ८^{२}; ४६, ६; ७; १५; ४७, ७; ४८, १; १०; १३–१६; ५४, १; ११; ५७, ४; ५८, ८; ६२, २; १२; १३; ६३, ८; ९; ७०, ५; ७१, २; ७; १०; ७३, ९; ७५, ५; ७६, २; ७७, ४; ७९, ७–९; ११; ८१, १; ७–९; ८२, १; ८४, ८; २०; ८५, १२; ८८, १; ८९, १^{२}; २^{२}; ३–५; ६^{४}; ७; ९^{२}; ९०, १; ४; ५^{२}; ६; ७; ८^{२}; ९; ९१, १; ४; ६; ८–१३; १५; १७; २३; ९२, १५; १७; ९३, ११^{२}; १२^{२}; ९४, १; १२; १६; ९५, ११^{२}; ९६, ८; ९^{२}; ९७, १–८; ९८, २; ३; ९९, १; १००, १–१५; १९^{२}; १०१, ८; १०; ११; १०२, ३^{२}; ९; १०; ११^{२}; १०३, ८; १०४, २; ५^{२}; ६^{२}; ७; ८^{४}; ९; १०५, १३; १९; १०६, १; २; ३^{२}; ४; ५^{२}; ६; ७^{२}; १०७, २^{२}; ३^{२}; १०८, ६; १३; १०९, ७; ८; ११०, ७; ९^{२}; १११, २^{२}; ३–५; ११२, २४^{२}; २५; ११३, ४^{२}; १६; १९^{२}; २०; ११४, २^{२}; ६; ७^{६}; ८^{५}; १०^{२}; ११; ११५, ६; ११८, २; १०; १२०, ३; ४; १२१, १४^{२}; १५; ७^{२}–९^{२}; १२२, ३^{२}; ६; १४; १२३, ३; १३; १२४, १; १२७, ११^{२}; १२८, २; ५; ७; १२९, ५^{२}; ८; ९^{३}; १०; ११; १३०, १; १०; १३१, ६; ७; १३२, ६; १३३, ६; १३४, ६; १३५, १; ३; ५; १३७, १; ३; १३८, ४; १३९, १; ५–७; १४०, १२^{२}; १३; १४१, १२^{२}; १४२, ८; १०^{२}; १४३, ६; ७; ८^{२}; १४७, ४; ५; १५३, ४; १५७, २; ३; ४^{२}; १५८, १; १६०, ५; १६१, १; ४; १३; १६२, १; ६; १२; २२^{३}; १६४, २६; १६५, ३–५; १६६, ६; १६७, १^{२}; २; १०^{२}; १६९, १; ४; ५; १७०, २^{२}; १७१, ३^{२}; ४; ५; १७२, ३; १७३, ९; १२; १३^{२}; १७४, १; १०; १७५, २; १७६, १; १७८, १; २^{२}; ५; १८१, ६; १८५, २–८; १८६, १^{२}; २^{२}; ३; ५; ६^{२}; ७; ८; १८७, ३; ७; १८८, ३; ७–९; १८९, २; ४; ५^{२}; १९०, ६; ८; **२.** १, २; ६^{२}; ७; ९; ११; १२; ३, ३; ६; ८; ६, ५^{३}; ६; ७, २; ५; ९, २^{२}; ६; ११, १४; २१; १५, १०; १६, ७–९; १७, ८^{२}; ९; १८, ९; १९, ९; २०, १–३; ९; २३, १; ६^{२}; ७^{२}; ९; १०; १२; २४, १^{२}; १२; १५; २७, १; ६^{२}; ७; १०; १४; २८, ३; ७^{२}; ९; १०; २९, २; ३; ६; ३०, ९; १०; ३१, २; ३; ३२, २^{४}; ४–६; ३३, १^{२}; ३–५; १३–१५; ३४, ६; ७; ९; १२; ३६, ३; ३८, १०; ३९, ३; ४^{२}; ५; ६^{२}; ७^{२}; ४१, ९; ११^{२}; १६; १७; २०; ४२, ३; ४३, २^{२}; ३; **३.** १, १५; १९^{२}; २२^{२}; २३; ३, ७; ४, २; ६; ९; ११; ८, ७; ९; १०, ६; ८; १३, १; ४^{२}; ६^{२}; ७; १४, ६; १५, २; ३; ५; ६^{२}; १६, ३; ५; १७, ५; १८, १; १९, १; ५^{२}; २०, १; २; २१, १; २; २३, २; २४, २; ५; २५, २; २६, ३; २८, १; २९, १०; ३०, ११; १९; २१; ३१, ८; १९; २०^{२}, ३२, १४; ३३, ८^{२}; ३५, १; ३७; ८; ११; ३८, ९; ४०, ३; ६; ८; ४१, १; २; ४; ४२, ७; ४३, २; ३; ४४, १; ४५, ५; ४७, २; ३; ५१, ८; ५२, १; ३^{२}; ४; ६; ५३, १३; १४^{२}; १७; १८^{२}; १९; २१^{२}; ५४, ३; ९; १२; १५–१७; १८^{३}; १९^{२}; २०^{३}; २२; ५५, २; ९; २१; ५६, ६; ६०, ६; ६२, ४; ९; १०; १६; **४.** १, ४; ५^{३}; १०; २, २; ११; १६; २०; ३, ४; ५; १४; ४, ३; ४; ११; १२; ५, १२^{३}; १३; १०, ३^{२}; ८^{२}; ११, २; १२, ६; १४, १; १५, १; १६, १; २; ८; १७; २०^{२}; १७, १७; २०; २०, १^{२}; २^{२}; ३; ४; १०^{२}; २१, १; ३; ६; १०; २२, १^{२}; २३, ७; २४, १; २९, १; ३; ३१, १; ३; ४; ३२, ५; ७; १६^{२}; २०; २१; ३३, ३; ८; ३४, १; ५; ३६, ८; ९^{२}; ३७, १; ७; ८; ३९, ५; ६^{२};

४१, ४; ५; ६; ११; ४२, १; १०;
४३, ४; ४४, ५; ६; ४६, २; ४७,
३; ४९, ३; ५०, २; ११; ५३,
१; ५; ६; ७^{२}; ५४, १^{२}; ३; ६;
५५, १; ३; ४; ५^{२}; १०^{२}; ५६, ४;
५७, १–३^{२}; ६^{२}; ७; ८; ५८,
१०; **५.** १, ८; २, ५; ३, ७^{२}; ९;
१२; ४, २; ४; ५; ८; ९; ५, ४;
५; ७; ९; ६, ८; ९; ८, ४; ९,
७^{२}; १०, १; २; ६; ७^{२}; ११, ४;
१२, ३; १३, ३; ५; १४, १; १६,
५; १७, ५; १९, ५; २०, १;
२२, ४; २३, ४; २४, १; ३^{२};
२५, १; ३^{२}; ४; ९; ३०, ३; ३१,
२; ११; ३३, २; ६; ७; ३५, २;
८; ३६, ५; ३८, १; ४; ३९, १;
४१, १; ६; ९^{३}; ११; १२; १५;
१६; १८; १९; २०; ४२, ३–५;
९; १३; १६; १८; ४३, १–३; ६;
११^{२}; ४६, ४^{२}; ५^{२}; ६; ७^{३}; ४९,
४; ५०, ३; ५१, ११^{२}; १२; १३^{२};
१४^{२}; ५४, ६; ५५, ९; १०; ५७,
७^{२}; ८; ५९, ६; ८; ६०, १;
६; ६१, १६; ६२, ९; ६३, ५;
६४, ५; ६^{२}; ६५, १; ६; ६८,
३; ७०, ३; ७१, १; ३; ७२,
३; ७५, ३; ७९, १^{२}; ३; ६; ८;
८०, ५; ८२, ४; ५; ८३, ५; ६^{२};
८७, ६; ८; ९; **६.** २, ७; ११;
४, १; २; ४; ७; ८; ५, ४;
८, ७; ९, ७; १०, १; ५;
११, १; २; ६; १२, ६; १३, २;
६; १४, ६; १५, ६; ९; १२; १५;
१९^{२}; १६, २; १२; २८; ३०^{२};
३१^{२}; ३२; ४४; १७, १४^{२}; १८,
५; १९, ६; ७; ८; २०, १; २१,
९; १२^{२}; २२, २; ४; ७; १०;
११; २३, ५; ९; २४, ५; ९; २५,
१^{२}; ७; ९; २६, १^{२}; ३३, १; ४;
५^{२}; ३६, ५; ३७, २; ३८, १;
३९, १; ४०, ३–५; ४४, ११;
१८^{२}; ४५, १; ४; १४; १७; २१;
२४; ३३; ४६, २; ३; ५; ६; १०;
४७, ७^{३}; ८; ९^{२}; ११; २८; ३०;

३१; ४८, ७; ९^{२}; १०; १५; १९;
४९, ८; १४; १५; ५०, ३; ४;
८; ९; ११; १२^{२}; १३; १४; ५१,
५; ६^{२}; १०; ११^{२}; १४; १५; ५२,
२; ३^{२}; ६; ९^{२}; ११; १२; १६;
१७; ५३, २; ४; १०; ५४, ५^{२};
१०; ५५, १; ५; ५६, ४; ५; ५९,
७; ९; ६०, १२; १४; ६१, ४;
६; ७; ९; १०; १४^{२}; ६३, ८;
६४, ४; ६५, १; ६^{२}; ६७, २; ६८,
७; ८; ६९, १; ५; ७०, ५; ६;
७१, ३^{२}; ७३, १; ७४, १–३; ४^{२};
७५, १०^{२}; १२^{३}; १७; १९; **७.**
१, ३; ५; ८; १२; १३; १८;
१९^{४}; २०; २२; २४; २५; २, १;
६; ७; ३, ७; ८; १०; ४, ४; ८;
५, ९^{२}; ७, १; ८, ३; ९, २; ३;
१०, ४; ११, ३; १२, २^{२}; १४,
३; १५, १; ३; ४; ६; ११;
१३–१५; १६, ५; ६; ८; ९; १७,
५; ७; १८, १; ४; १९, ७; ११;
२०, १; ७; ९; १०; २१, १; ५^{२};
२३, ४; २४, १; ३–६; २५, २^{२};
२६, १; ५; २७, १; ४^{२}; ५; २८,
१; ४^{२}; ५; २९, २; ४; ३०, १;
३१, ३–५; ३२, १; ५; १९; २५;
२६^{२}; २७; ३४, १४; १५; १७;
१८; २०; २१; २२^{२}; २३^{३}; २५^{२};
३५, १^{३}; २^{५}; ३^{५}; ४^{४}; ५^{४}; ६^{३};
७^{५}; ८^{४}; ९^{५}; १०^{४}; ११^{३}; १२^{४};
१३^{४}; १४; १५^{२}; ३६, ७^{३}; ८;
३७, २; ५; ६^{३}; ८^{३}; ३८, ३;
५–८; ३९, १; ३; ७^{२}; ४०, २;
४; ६; ४१, ३^{२}; ५; ६; ७^{२}; ४२,
५^{२}; ६; ४३, ३; ५^{२}; ४४, ५^{२};
४५, ३^{२}; ४; ४६, १; २^{२}; ३^{२}; ४^{३};
४७, ४^{२}; ४८, ४^{३}; ५०, १; ५१,
२; ३; ५२, ३; ५३, २; ३; ५४,
१^{३}; २^{२}; ३^{२}; ५५, १; ६; ५६,
९; १६; १७; २१; २२; २५^{२};
५७, ५^{२}; ६; ७^{२}; ५८, ३^{२};
५; ६; ५९, ६^{२}; ८; ६०, ७;
१०; १२^{२}; ६२, २^{२}; ३^{२}; ४; ५^{३};
६^{३}; ६४, १; २; ३^{२}; ६५, २; ४;

६६, १; ३; ५; ६७, ५; ६^{२}; १०;
६८, १; २; ९; ६९, ५; ७०, १;
७; ७१, २; ४; ६; ७२, २^{२}; ५;
७३, ४^{२}; ५; ७४, ३; ७५, २; ८^{३};
७६, ६; ७; ७७, ४; ५^{२};
७९, ५; ८२, १; ८३, २; ५; ८४,
२^{२}; ३^{३}; ८५, १; ८६, ५; ८^{२};
८९, ५; ९०, ६; ९२, १; ३;
९३, ४; ६; ८; ९४, ३^{२}; ८; ९६,
२; ५; ९७, २^{२}; ४^{२}; ५; १००,
२; १०२, १; ३; १०३, १०;
१०४, ७; १०; ११; २३^{२}; **८.**
१, ९; २१; २, १५; ३, १^{२}; २^{२};
११; १२; १८; ४, ३; १५; १६^{२};
५, ४; ७; ९; १०; २०; २१; ३२;
३६; ६, २३; २५; ३६; ७, ११;
१३; २७; ३२; ८, १; ४; ७; ९;
१३^{३}; १७^{२}, २०; ९, ११^{२}; १०,
३; १२, ६; ३३; १३, ३; ५^{२};
१३; १६; १८; २२; २५; १५,
१३; १६, ११; १२^{२}; १७, २; ४;
१८, ६–१०; १२; १३; १७; १८;
२१; २२; १९, ४; १९; २७;
२०, २; ८; १०; १८; २२–२४;
२६^{२}; २१, २; ६; ८; ९; १०;
१२; २२, ७; १०; १४;
१७; २३, १०; १२^{२}; २७; २९;
२४, ७; ११^{२}; २६; २५, १०; ११;
१४; २६, ७; २०; २५; २७, २–६;
९; १०; १४^{२}; २८, ३; ३०, ३^{३}; ३१,
१३, ३२, ७–९; १२; ३४, ६^{२}; ७;
१२; १४; १५; ३५, ४; १०; ३९,
१; १०; ४०, १; २; ९; ४२, २^{२};
४३, २२; ४४, २; ५; ११; १४;
१९; २२; ३०; ४५, ८; १५;
१८; १९; ३३; ३४; ४६, ९–११;
१३; २५; ४७, ५; ८; ९; ११;
४८, ४^{२}; ६; ७; ८^{२}; ९^{२}; १२;
१४^{२}; १५^{२}; ४९, ४; ५; ७; ५०,
५; ५१, ५; ५२, ५^{२}; ५३, ३;
५४, ३^{३}; ५; ६; ५९, ७; ६०,
८–१०; ११^{२}; १२; १४; १८;
२०; ६१, १; १३^{२}; १५^{३}; १६;
१७^{२}; ६५, ५; ६६, ८; १४^{२}; ६७,

२; ५; ६; ८^{२}; ९; ११; १२; १४; १५; २०; ६८, १२^{३}; ७०, ९; १०; १५; ७१, ३; ६; ७; ९; १०; १३; १५; ७३, १४; ७५, २; ८; ९; ११^{२}; १२; १३; ७८, १–३; ७९, ७^{२}; ८^{२}; ८०, १–६; ९; ८१, ४; ६^{२}; ८३, २–४; ७; ८४, ६; ८६, १; ९०, १; ६; ९१, ४; ६; ९२, ३; ९^{२}; १०; १५; १९; २६; २७; ३१; ९३, ३; १०; १८; १९; २१; २८; २९^{२}; ३०–३४; ९५, ८; ९; ९६, ८; २०; ९७, ६, ७^{४}; १३; ९८, ४; १०–१२; १००, ११; १०१, ४^{२}; ९; १०; १०२, २; ८; ९; १०३, १; ९; १२; **९.** १, ५; ४, १; ५; १०; ५, ८; ८, २; ७; ८; ९, ७; १०, ८; ११, ३; ९^{२}; १३, ४; ५; १९, १; २०, ३; २३, ३; २९, ५; ३०, ३; ३२, १; ३५, १^{२}; २; ३; ३६, ३^{२}; ४०, ३; ५; ६; ४१, ६; ४२, ६; ४३, २; ४४, १; ४–६; ४५, २; ३; ४९, १; २; ४; ५२, १; ५; ५४, ४; ५५, १; ३; ५७, ४; ६१, ३; ५; ६; ९; १२; १४; १५; २३; २६; २८; ३०; ६२, २१; २४; ६४, ३; १२; १८^{२}; ६५, १३; १७; १८; २१; २४; ६६, १३; १९; ३०; ६७, ६; १०^{२}; २२^{२}; २३; २४^{२}; २६; ६८, १०; ६९, ७; ८; ७०, ९; १०; ७२, ८; ९^{२}; ७६, ३; ७७, ३; ४; ७८, ४; ५; ७९, १^{३}; २; ८१, ३^{२}; ४; ८४, १; ८५, २; ४; ८; ८६, १८^{२}; ३८; ४८; ८८, ७; ९१, ६^{२}; ९३, ४; ५; ९६, ३^{२}; ११^{२}; १४; ९७, ४; १५–१७; २१; २५; २८; ३६; ३९; ४४^{२}; ४८; ५०; ५१^{२}; ५३; ९८, १; १००, ५; १०४, ५; ६; १०५, ४; ५; १०६, ७; ९; १०७, ६; १०८, १४; १०९, ९; ११०, १; ७; ११२, १; ११४, ३; ४^{२}; **१०.** ३, ७; ४, १; ७^{२}; ५, ७; ७, १^{२}; ७^{४}; ९, १–३; ४^{२}; १०, ४; ११, २^{२}; ८; ९^{२}; १२, २; ४; ५; ८; १३, २; १४, २^{२}; ६; १४; १५, १; ४; ६; ८; १७, १०; १८, १; ३; १९, ६; ७; २१, ४; २२, ६–९; १५; २३, ७; २४, २; ३; ६; २५, १; ३; ४; ६; ७^{२}; ८^{२}; ९; २६, ३; ९; २८, ५; १२; २९, ४; ३०, ११; ३१, १; ५; ३३, ३^{२}; ३४, १४^{२}; ३५, २–७; १०–१३; ३६, २^{२}; ३; १४^{२}; ३७, ५; ६^{२}; ९; १०^{२}; १२; ३८, १–३; ३९, २^{२}; ४२, ३; ११^{२}; ४७, ८; ५२, ४; ५३, ३^{२}; ५७, १; ५; ५९, २; ४^{२}; ५^{२}–७^{२}; ६१, १४; १८; २१; २७; ६३, १; ६–८; ११; १२; १५^{२}; १६; ६४, १; ६; ९; १०^{२}; १३^{२}; ६५, ३; ६६, ३^{४}; ५; ७; १०; १२; ६७, १; ६८, १२; ६९, ४; १२; ७०, ११; ७४, ३; ७६, १; ४; ६; ७७, ८; ७८, ८; ८१, १; ७; ८२, ३; ८३, २; ३; ८४, २; ६; ८५, २३^{२}; ३७; ४३; ८६, ८; ८७, २०; २१; ८९, १५; ९१, १३; ९२, १२; १३; ९३, १^{३}; ५–७; ९^{२}; ९७, १५; ९८, ४; ९; १०; १२^{२}; ९९, १; ८; १००, १^{२}; ३–५; ७; ९; १०१, ३; १०२, १; १०५, ८; १०६, ९; ११; १०७, ७; १०८, २; ३; ११०, २; ८; ११२, १०; ११३, १०; ११५, ५; १२१, ९; १२४, १^{२}; १२६, ३^{३}; ६; १२७, ४; ६; १२८, ४–६; ८^{३}; ९; १३०, ६; १३२, ७; १३३, ३^{२}; ४–७; १३५, १; ५; १३९, ५^{२}; १४१, १^{४}; २^{२}; ४; ६^{२}; १४२, २; १४३, ४; १४७, ५; १४८, १; १४९, ४; १५०, १^{२}; ३; ५; १५१, ५, १५२, २; ४; १५६, १; २; १५७, २; १५८, १^{२}; २; ३^{३}; ४; १६४, ४; ५; १६५, १; २^{३}; ३^{२}; १६७, १; २; १६९, ४; १७४, २^{२}; १७६, २; १८२, २^{४}; १८६, १^{२}; २^{३}; ३; १८७, १–५; १८८, ३; १९१, १.

नक् **७.** ७१, १.

नकिः **१.** २७, ८; ४८, ६; ५२, १३; ६९, ४; ८४, ६^{२}; १५५, ५; १६५, ९; **२.** २४, ७; २७, १३; ३८, ७; **३.** ३८, ८; ३९, ४; ४९, २; **४.** १७, १९; ३०, १^{२}; २३; ४२, ६; **५.** ८५, ६; **६.** ७, ५; २५, ५; २७, ३; ३०, २; ४४, १०; ६७, १०; **७.** ३२, ५; १०; १६; ५६, २; **८.** २०, १२; २१, १४; २४, १५; १७; २८, ४; ३१, १७; ३२, १५^{२}; ३३, ८; ४५, २१; ५९, २; ६१, ६; ६८, ८; ७०, ३; ८४, ९; ८८, ३; ६; **१०.** १०, ५; २२, ५; ३१, ११; ३९, ११; १११, ७; १३२, ३; १३४, ७^{२}.

नकीं **८.** ७८, ४; ५.

नुक्तऽभिः **७.** १०४, १८.

नक्तं **१.** २४, १०^{२}; १२; ३४, २; ९०, ७; ९८, २; ११६, २०; १२७, ५; १३९, ५; १४४, ४; **४.** ३०, ३; **५.** ७, ४; ७६, ३; **६.** ३, ६; **७.** १५, १५; ७१, १; २; १०४, ११; १७; **८.** ७, ६; १८, ६; २५, ११; २७, २; ६१, १७; ६४, ६; ९६, १; **९.** ९७, ९; १०७, २०; **१०.** ३४, १०; ८८, ६; ९३, ५; ९५, ४.

नुक्तुऽया **४.** ११, १.

नक्ता **१.** ७३, ७; **७.** ४२, ५.

नक्ताः **२.** २, २.

नक्तोपसा **१.** १३, ७; ९६, ५; ११३, ३; १४२, ७; **९.** ५, ६.

नक्षत् **१.** १२१, ३; १७३, ३; **६.** ६३, ६; **७.** ३९, ६.

नुक्षुतु **१.** ३३, १४; **१०.** ७४, २.

नुक्षुतुः **६.** ४९, २.

नक्षति **२.** २०, २; **१०.** ३, ५.

नुक्षुति **१.** ९५, १०; **४.** ४३, ५.

नक्षते **६.** २२, ५.

नुक्षुत्ऽद्राभं **६.** २२, २.

नक्षत्रः **६.** ६७, ६

नक्षत्रं ७. ८१, २; ८६, १; १०. ८८, १३; १११, ७; १५६, ४.
नक्षत्रऽशवसां १०. २२, १०.
नक्षत्रा १. ५०, २.
नक्षत्राणां १०. ८५, २.
नक्षत्रेभिः १०. ६८, ११.
नक्षत्रैः ३. ५४, १९.
नक्षथः १. १८०, २.
नक्षन् ७. २३, ४.
नक्षन् ८. ५४, १.
नक्षत १०. ८८, १७.
नक्षन्त ७. ४२, १; ५२, ३; ८. ९२, २७; १०३, १.
नक्षन्तः ६. ४९, ११; ६३, ३.
नक्षन्ति १. १६६, २; ६. ३४, ३.
नक्षन्ते १. ६६, ५; ६. ४५, २८; ७. ३७, ७; ५८, १; ८. ५४, २.
नक्षमाणः १०. ६८, २.
नक्षमाणा ७. ३१, ८.
नक्षमाणाः ७. ९३, ३.
नक्षसे १. ३०, २०.
नक्षस्व ८. ५४, ७.
नक्षामहे ८. ६०, १०.
नक्षि ५. २४, २.
नक्ष्य ७. १५, ७.
नखं १०. २८, १०.
नखेभ्यः १०. १६३, ५.
नखेषु १. १६२, ९.
नग्नः १०. ६१, ९.
नग्नता १०. ३३, २.
नग्नं ४. २५, ७; ८. ७९, २.
नग्नाः ८. २, १२.
नद् ७. १०४, २३.
नतऽभ्यः १०. ६०, ६.
नदनुं ८. २१, १४.
नदनुऽमान् ६. १८, २.
नदं १. ३२, ८; ८. ६९, २[२].
नदयन् ७. ७, २; ९. ९७, १३.
नदयन्त १. १६६, ५.
नदयोः १०. १०५, ४.
नदस्य १. १७९, ४; २. ३४, ३; १०. ११, २.
नदी इति १. १३५, ९.
नदीऽतमे २. ४१, १६.
नदीनां २. १५, ३; १९, २; ३. ३३, ६; १२; ५. ५२, ७; ७४, २; ६. १७, १२; ३०, ३; ७२, ३; ७. ३४, १०; ११; १६; ८७, १; ९५, २; ९६, १; ८. ६, २८; २६, १८; ३१, १०; ९६, ११; १०. १३९, ६.
नदीभिः ५. ४१, १९.
नदीऽवृतं १. ५२, २; ८. १२, २६.
नदीषु ७. ५०, ३; ८. २, २; ३३, १२; ९. ५३, ४; ६३, १७; ६८, ६; ७६, १; ८८, ५; १०७, १३.
नद्यः १. ५४, १; १०; ५५, २; ६२, ६; १०२, २; १३०, ५; १५८, ५; १८१, ६; २. ३५, ३; ३. ३३, ४; ४. १६, २१; ५५, ६; ५. ४२, १२; ४५, २; ४६, ६; ४७, ५; ५५, ७; ७. ५०, ४; ६०, ७; ८. ९६, १४; ९. ९, ४; ८६, ८; ९२, ४; १०. २८, ४; ६४, ८; ९५, ७.
नद्यं १. १३१, ५.
नद्याऽइव २. ३९, ५.
ननक्षुः ५. १५, २.
ननक्षे ८. ५१, ८.
ननक्षे ९. ९३, १; १०. ९५, ४.
ननमः १. १७४, ८; २. १९, ७.
नना ९. ११२, ३.
ननांदरि १०. ८५, ४६.
ननाम १. ४८, ८; २. ३३, १२; ४. २५, २.
ननाश ९. ६७, ३०; १०. १७, १.
ननु १०. ५४, २; ८४, ३.
नंस्यानि २. २४, २.
नंदंति १०. ७१, १०.
नक्षमत् ८. ४३, ८.
नपात् १. १४३, १; २. ३१, ६; ३५, १; २; ७; ९; १०; १३; ६. ५०, १३; ५२, १४; ७. ३५, १३; ४७, २; १०. ८, ५; ३३, ७; ९२, १३.
नपात् १. ४२, १; ५८, ८; २. ६, २; ४. ३२, २२; ५. १७, ५; ६. १६, २५; ५५, १; ८. १७, १३; ७१, ३; ९; ८४, ४; १०. २०, १०; ३०, ४; ११५, ८; १४०, ३; १४९, २.
नपातः ३. ६०, ३; ६. ५०, १५; ८. ६५, १२.
नपातः १. १६१, १४; ४. ३४, ६; ३५, १; ८; ३७, ४.
नपातं १. २२, ६; ३७, ११; १२२, ४; १८६, ५; २. ३५, ३; ३. ९, १; २७, १२; ५. ३२, ४; ४१, १०; ६. २०, ११; ४८, २; ७. १६, १; १७, ६; ३४, १५; ८. १९, ४; ४४, १३; ६०, २; १०. १०, १; १५, ३; ३०, ३.
नपाता १. १८२, १; १८४, १; ८. २५, ५; १०. ६१, ४.
नपाता १. ११७, १२; ३. ३८, ५; ४०; ४४, २.
नप्तीः ९. ६९, ३.
नप्तीभिः ९. १४, ५.
नप्तुः २. ३५, ११; ७. १८, २२.
नप्तृऽभिः १०. ८५, ४२.
नप्त्यः १. ५०, ९.
नप्त्यं ३. ३१, १.
नप्त्या ८. २, ४२.
नप्त्योः ९. ९, १.
नप्त्रा ६. १३, ३; १०. ३०, १४.
नप्त्रे २. ३५, १४; ५. ७, १; ८. १०२, ७.
नभः १. ७१, १०; १७४, ८; ३. १२, १; ५. ४१, १२; ८३, ३; ७. ९७, ६; ८. ९, ८; ९६, १४; ९. ७१, १; ७४, ४; ८३, ५; ९७, २१.
नभःऽजाः १०. १२३, २.
नभःऽजां १०. ३०, ९.
नभःऽजुवः १. १२२, ११.
नभःऽभिः २. ४, ६.
नभःऽवित् १०. ४६, १.
नभनून् ५. ५९, ७.
नभन्तां ८. ३९, १; १०. १३३, १.
नभन्यः १. १४९, ३.
नभन्यं १. १७३, १.

नभन्यंस्य ७. ४२, १.
नभन्वः ४. १९, ७.
नभंसः १. १६७, ५.
नभंसा ९. ७१, ३; ८६, १४.
नभस्सयं ९. ६९, ५.
नभंस्वतीः ८. २५, ६.
नभाकऽवत् ८. ४०, ४; ५.
नभ्याऽइव २. ३९, ४.
नभ्यानि १. १६४, ४८.
नम १. १२९, ५; १०. १४२, ६.
नमंउक्तिऽभिः ८. ४, ६.
नमः १. १, ७; २७, १३[४]; ५१, १५; ६२, २; ६५, १[२]; ७१, ६; ११४, ११; १३६, १; ६; २. २१, २; २८, ८; ३६, ६; ३. ३३, ८; ५१, ४; ५४, ३; ४. २१, ५; २३, ४; ४४, ३; ५. ४७, ७; ४९, ५; ७३, १०; ६. ५१, ८[५]; ७५, १५; ७. ३६, ५; ९४, ४; ८. ७२, १५; ७५, १०; ८४, ५; ९. ६७, २९; १०. ४, ७; १४, १५; १५, २; ३४, ८; ३७, १; ६०, १; ६८, १२; ८५, १७; ९२, ४; ११५, ९[२]; १६५, ४.
नमःऽउक्तिं १. १८९, १; ३. १४, २; ५. ४३, ९.
नमःऽभिः १. २४, १४; २७, १; ७७, २; १५३, १; २. ३, ५; ३३, ४; ८; ३८, ९; ३. ४, ३; २५, ३; ४. ४२, ९; ५८, २; ५. १, ७; २८, १; ४१, २; ८; ४२, ११; ६०, १; ६. १, ९; १०; ५०, १; ५१, ९; ६०, ३; ७. ७, १; ८, १; ३३, १३; ३४, १४; ४२, ३; ४३, १; ५३, १; ६१, ६; ६३, ५; ८४, १; ९५, ५; ८. १९, १३; २२, ३; १३; ६२, ५; ९६, ६; ९. १६, ५; ९६, २; १०. ६, ५; १३, १; ४६, २; ४.
नमःऽवाके ८. ३५, २३.
नमःऽवृक्तिं १०. १३१, २.
नमःऽवृधं ३. ४३, ३.
नमःऽवृधा ३. ६२, १७.
नमःऽवृधासः ७. २१, ९.
नमःऽवृधैः ८. १३, ९.
नमते ६. २४, ८.
नमध्वं ३. ३३, ९; ७. ५६, १७.
नमंत ५. ३२, १०; ७. ३१, ९; ४१, ६; ८. ६, ४; १०. ३०, ६.
नमंतां ५. ३६, ६; ६. ५०, ४; १०. ४२, ६; ५१, ९; १२८, १.
नमंति ७. ५६, १९; ८. ९७, १२.
नमंते ४. ५०, ८; १०. ३४, ८.
नमयन् ९. ९७, १५.
नमयिष्णवः ८. २०, १.
नमंसः १. १७१, २; १९०, ३; ८. २३, ९.
नमंसा १. ५७, ३; ६२, ११; ६३, ९; ८४, १२; ११४, २; ५; १२८, २; १५२, ७; १५८, २; १७१, १; १८५, ७; १८६, ४; २. २३, १३; ३०, ११; ३४, १४; ३५, १२; ३. १, २; २, १४; ३, ८; १४, ५; ३१, ५; १९; ३२, ७; ५९, ५; ६१, ५; ४. ५, ११; ७, ७; १९, ६; ३४, ६; ५०, ६; ५. १, १२; ४, ९; ८, ४; १२, ६; ४०, ८; ४१, १६; ४३, २; ६; १४; ४९, २; ८३, १; ६. १, ४; ६; ११, ४; ५; १५, ८; १६, ४६; ५१, ८; ५२, १७; ६७, २; ३; ६९, ६; ७. २, ४; १२, १; १६, १; ४४, २; ८३, ८; ८६, ४; ९१, १; ९३, ७; ९७, ३; ८. १९, ५; २१, ६; २३, २२; २६; ४३, १२; ४६, १७; ४९, ६; ७१, १०; ७२, १०; ९६, १२; ९. ११, ६; ८९, ५; १०. ३१, २; ४७, ६; ६१, २६; ६३, ५; ६९, १२; ७०, २; ७९, २; ८५, २१; २२; ९२, ९.
नमंसि ४. २१, ५.
नमंसे ८. २५, ७.
नमस्य १. ४४, ६; २. ३३, ८; ५. ५२, १३; ८. ४२, २.
नमस्य ९. ११४, २.
नमस्यः २. १, ३; १०; ३. ५, २; २७, १३; ५९, ४; ७. ३८, ३.
नमस्यत ३. २, ८.
नमस्यत १. ८४, ५; ३. ६२, ५.
नमस्यन् १. ३३, २.
नमस्यंतः १. ११५, ३; १२७, ७; ४. ६, ११.
नमस्यंति १. ३६, १९; ३. ६२, १२.
नमस्यंतीः ३. ५७, ३; ९. ९५, ३.
नमस्यन्निति नमस्यन् १. ७२, ५.
नमस्य १. ७२, ५.
नमस्याः १०. १०४, ७.
नमस्यानि १०. ६३, २.
नमस्यामः ३. १७, ४.
नमस्युः ८. २७, ११.
नमस्युऽभिः १. ५५, ४.
नमस्येभिः ६. ६८, ३.
नमस्यैः ७. ९५, ४.
नमस्व ८. ७५, ५.
नमंस्वत् १. १८५, ३.
नमंस्वंतः १. १६४, ८.
नमंस्वंता ५. ६२, ५.
नमंस्वान् १. १७१, २; ४. ४१, १; ६. ६३, १; ७. ६६, १; ८५, ४; १०. ६१, २५.
नमस्विनः १. ३६, ७; ७. १४, १; ३६, ५; ८. १३, १०; ७५, १४; १०. ४८, ६.
नमस्विनं १. १६६, २.
नमीं १०. ४८, ९.
नमीं ६. २०, ६.
नमुचिं १. ५३, ७; २. १४, ५; ७. १९, ५; १०. ७३, ७.
नमुचेः ५. ३०, ७; ८; ६. २०, ६; ८. १४, १३.
नमुचौ १०. १३१, ४.
नमे ३. ३९, ६.
नमे १. १३९, ९[२]; ६. ५१, ९; ७. ३२, २०.
नमेते इति २. १२, १३.
नम्नंते १. १४०, ६.
नम्नमाने इति १०. ८२, १.
नम्नमीति ५. ८३, ५.
नम्या १. ५३, ७.
नम्रं १०. ४९, ५.
नर्य १. १८९, १.

नय १. ४२, ७; ८; ६. १५, १६; ४७, ७; ५३, २; ५४, १; ८. ४४, ८; ७१, ६; १०. ४५, ९; ८७, ९; १३३, ६.

नयः ४. ३०, १९.

नयत् १. ३६, १८; ३. ९, ५; ३१, ६; ६. ४, ६; ८. १७, १५.

नयंत १०. ३४, ४.

नयत ३. ६, १; ४. ५८, १०; ५. ५५, १०; १०. ६६, १२; १०१, २.

नयतं २. ३९, ५.

नयंति ४. २१, ४.

नयति १. १५५, ३; २. २६, ४; ५. ३४, ६; ६. ७५, ६.

नयतु १. ९०, १; २. ३, १०; ४. १, १०; १०. ८५, २६; १८२, १.

नयंथ १. ४१, ५; ७. ५९, १; ८. १९, ३४; १०. ६३, १३.

नयथ १०. १३७, १.

नयथः ५. ६५, ६; ६. ७२, २.

नयध्वं २. १४, ९; १०. १६५, ५.

नयंन् १. ७९, ३; ९. ८६, ३२.

नयंत १. १४८, ३.

नयंतः १०. ४६, ५.

नयंति १. ४१, ३; १६२, २; ४; ६. ५१, १०; १०. १२६, १.

नयंति १. ६४, ६; ८३, २; ९५, २; १२६, ४; १४६, ४; ३. ८, ४; ५३, २३[२]; २४; ४. १, ९; ७. ६०, ६; ७; ९. ८७, १; १०. ११४, ७.

नयंती ७. ७७, ३; १०. ५६, २.

नयंतीः ६. ६५, २.

नयंतु १०. ८५, ३१.

नयंतु १. ४०, ३; ७. ६४, ३.

नयंमानः १. १७३, ३; ९.

नयंसि १. १२९, १; ६. ४५, ६.

नयसि २. २३, ४; १०. ७५, ४.

नयसे १०. ८४, ३.

नयस्व ३. ३५, ३.

नयाति १०. १६१, ३.

नयामसि ८. ४७, १७.

नयिष्ठाः १०. १२६, ३.

नरंः १. ८, ६; ३९, ३; ६२, ३; ६३, ६; ६४, ४; १०; ६७, २; ७०, ५; ७३, ४; ८३, ४; ८५, ८; १००, ८; १०४, २; ११५, २; १२१, २; १२४, १२; १२७, ६; १५४, ५; १६६, १३; २. १, ९; १९, १; ३६, १; ३. २, ६; ३, ८; ८, ६; ३५, ८; ५४, ४; ६२, १२; ४. १, १५; ३, ११; २४, ३[२]; २५, ८; ३३, ६; ३४, ९; ३६, ५; ४२, ५; ४४, ६; ५७, ४; ५. ७, २; ९, ७; १०, ३; ४; ११, २; ४; २९, १२; ३०, २; ३३, ५; ५२, ५; ६; ८; ११; ५३, ३; ६; ५४, ३; ८; ५५, ३; ५७, ८; ५९, २; ५; ६१, ३; ६. १, २; २, ३; २९, १; ४; ४०, २; ४६, १; ४७, ३१; ५९, ७; ६८, ४; ७५, ११; ७. १, १; ४; ९; १०; ३, ५; ८, १; १५, ९; १६, ३; १९, ८; ९; २७, १; ३१, २; ५६, १; ५७, ६; ५९, ७; ७४, ६; ८२, ९; ८३, २; ९१, ३; ४; ९३, ३; ९४, १०; ९७, १; १०३, ९; ८. १, १७; ७, २९; २०, ६; ७; २५, १५; २७, ६; ३३, २; ३८, ३; ६५, ८; ६८, ५; १४; ७१, १४; ९९, १; ९. १७, ७; ७२, २; ७४, ४; ८०, ४; १०१, ३; १०. २०, ८; २९, ५; ४०, १०; ५०, ३; ६३, १७; ७६, ६; ७; ८०, ५; ८४, १; १०७, ३; १४७, २.

नरः १. २१, २; २३, ११; ३७, ६; ४०, ६; ४१, ५; ८६, ८; ११०, ८; १११, ३; १६१, ११; १६५, ११; २. ३, ३; १४, ८; ३६, २; ३. १६, २; २९, ५[२]; ६०, १; ४. ३४, ४; ५; ५. ५३, १५; ५४, १०; ५९, ३; ६१, १; ६. ४९, ११; ७. १८, २५; ३३, ४; ४८, १; ५९, ४; ६६, १३; ८. २०, १०; १६; ९. ११, १; १०. ७६, ८; १०१, १२; १०३, २; १३.

नरं १. २५, ५; ३०, ९; ३१, ६; १५; १००, ८; ११२, २२; ३. ५१, २; ६. ४४, ४; ८. १६, १; २४, १९; ४०, २; ९२, ८; ९७, १०; ९. ९७, ४९; ५२; १०. ३८, ४.

नरा १. ३, २; ११७, १८; १५१, ९; ५. ७३, ६; ६. ६२, १; ६३, ५; ७. ६९, ६; ८. १०१, २; १०. १४३, ३.

नरा १. २, ६; ४६, ४; ४७, ८; ११२, ३; १६; ११६, ७; ११; १२; १४; ११७, २; ४; ६; ७; २४; ११८, ५; १०; १८२, ८; १८३, ३; १८४, २; २. ३९, ८; ४१, ३; ३. ५८, ६; ४. ४७, ४; ५. ४९, १; ६४, ७; ७३, ७; ७५, ६; ६. ५०, १०; ६०, ९; ७. ६६, १९; ७४, २; ४; ८२, ८; ८३, १; ९१, ६; ९४, ३; ९९, ४; ८. ५, १६; २२; ८, ५; ६; १७; २०; २१; २२, ८; १२; १७; २६, ४; ११; १६; ३५, २३; ३८, ४; ४०, ३; ८५, ४; ८७, १; २; १०१, ८; १०. ४०, १; ३–५; ४१, २; १४३, ३; ४; ६.

नरा १. १२२, १०; १४९, २; १६७, १०; १७३, ९; १०; १७४, १०; १८०, ८; १८६, ६; ७; २. १, ५; २०, ३; ३४, ६; ६. २४, २; ६८, ४; ७. १९, १०; १०. ४५, १२.

नराशंसः १. १४२, ३; २. ३, २; ३८, १०; ३. २९, ११; ५. ५, २; १०. ७०, २; ९२, ११; १८२, २.

नराशंसं १. १३, ३; १८, ९; १०६, ४; ९. ८६, ४२; १०. ६४, ३.

नराशंसस्य ७. २, २.

नरिं १. ८५, ९; ८. ९६, १९.

नरैः १. ६२, १; ४. २५, ४; ६. ४२, १; ९. ९८, १०; १०. ५०, २.

नरेऽस्यां ४. ३३, ८.

नरौ १. ११७, ३; १८०, ४.

नर्तयन् १. ५१, ३.

नर्यः १. ६३, ३; १२१, १२; ४. २५, १; २९, २; ५. ४१, ९; ६. २४, २; ७. १, २१; २०, १; ९५, ३; ९. १०५, ५; १०७, १; १०. २९, १; ७; ५०, २; ६१, ५; ९५, १०.
नर्यऽअपसं ८. ९३, १.
नर्यं १. ४०, ३; ५४, ६; ११२, ९; २. २२, ४; ६. २३, ४; ५३, २; ७२, ५; ७. २०, ५; ४८, १; १००, १; १०. ७४, ५; १४७, १.
नर्यस्य १. १८०, २; ७. २५, १.
नर्या १. ७२, १; १६६, ५; १८५, ९; ३. ३४, ५; ४. १६, १६; १९, १०; ७. ४५, १; ८. ९६, २१.
नर्याः ६. २९, २; ७. ७, ६.
नर्याणि ४. १६, ६; ३६,८; ७. २१, ४.
नर्याय १. १२१, ३; ४. २५, ४; ८. २, २३.
नर्येभिः १०. ९९, १०.
नर्येषु १. १६६, १०.
नळाःऽइव ८. १, ३३.
नवं १. ३२, १४; ५३, ९; ५४, ६; ८४, १३; ११६, २४; २. १४, ४; १९, ६; ३. ९, ९; ४. २६, ३; ४८, ४; ५. २९, ६; ६. ४७, २; ७. १९, ५; ९९, ५; ८. ९३, २; ९. ६१, १; १०. २७, १५; ४९, ८; ९८, १०; १०४, ८.
नवः २. १८, १; ३. ११, ५; ४. ५१, ४.
नवःऽनवः १०. ८५, १९.
नवऽग्वः ९. १०८, ४; १०. ६२, ६.
नवऽग्वाः १. ३३, ६; ५. ४५, ७; ११; ६. ६, ३; २२, २; १०. १४, ६; ६१, १०; १०८, ८.
नवऽग्वासः ५. २९, १२.
नवऽग्वे ४. ५१, ४.
नवऽग्वैः १. ६२, ४; ३. ३९, ५.
नवऽजाः ४. ६, ३.
नवऽजातः ५. १५, ३.
नवऽजातं ७. ९३, १.
नवऽजातस्य ७. ३, ३.
नवऽज्वारः १. ४२, ८.
नवतिः ४. ४८, ४; १०. ९८, १०.
नवतिं १. ३२, १४; ५३, ९; ५४, ६; ८०, ८; १२१, १३; १३०, ७; १५५, ६; २. १४, ४; १९, ६; ३. १२, ६; ५. २९, ६; ६. ४७, २; ७. १९, ५; ९९, ५; ८. ९३, २; १०. ४९, ८; ९८, ११; १०४, ८.
नवती १०. ३९, १०.
नवतीः १. ८४, १३; ४. २६, ३; ९. ६१, १.
नवतीनां १. १९१, १३.
नवत्या २. १८, ६.
नवंत १. ६६, ५; ६९, ५; ५. ४५, ८; १०. २२, ९.
नवंत ४. ३, ११; ६. ७, २; ७. ४२, १; ९. ८८, २; १०. १२०, २; १७६, १.
नवंतं ६. १७, १०.
नवंते १. १६४, ३; ६. ७, ४; ९. ८६, २५; २७; ९७, ३५; १००, १; १०. ७१, ३.
नवऽपदी १. १६४, ४१.
नवऽभिः १०. ३९, १०.
नवं १. २०, ६; ५. ९, ३; ७. १५, ४; ८. २४, २३; ६९, १५; ९. २१, ६; ८६, ३६; १०. ८६, १८; ८९, ७; १३५, ३; १४३, १.
नवमं ५. २७, ३.
नवमानस्य १. १९०, १; २. ३४, १०.
नवया २. २४, १.
नवऽवास्त्वं १. ३६, १८; ६. २०, ११; १०. ४९, ६.
नवस्य ८. २३, १४.
नवऽस्रक्ति ८. ७६, १२.
नवस्वःऽइव ४. ३४, ५.
नवा १. ९५, ७; १४४, ५; ८. ४५, २५.
नवाः ५. ६, ८.
नवानां ८. ५, ३७; १०. ८९, १७.
नवानां १. १९१, १३.
नवानि ७. ६१, ६.
नवाभिः ४. ३१, १३.
नवामहे ८. ८८, १.
नवायां १०. १६०, ५.
नवासु १. ९५, १०.
नविष्टौ ८. २, १७.
नविष्ठं ५. ३२, ११.
नविष्ठया १. ८२, २; ८. २०, १९; २५, २४.
नाविष्ठाय ५. २७, ३.
नवीनोत् ६. ३, ७.
नवीनोत् ७. ८७, २.
नवीयः २. १९, ८; ६. १८, १५; २१, १; ७. २६, १; ३५, १४; ३६, २; ८. ४०, १२; ९. २३, २; १०. ५९, १; ६१, ११; ६९, ३; १७९, ३.
नवीयसः १. १३१, ६[२].
नवीयसा १. १२, ११; ६. १६, २१; ८. ३९, ६.
नवीयसी ७. ५९, ४; ८. १२, १०; ७२, ९; १०३, ९.
नवीयसीः ९. ८६, ३२.
नवीयसीं १. १३८, ३; ८. ५१, ५; ९५, ५; १०. ९१, १३.
नवीयसे १. १५६, २; ९. ९, ८.
नवीयान् १. ११०, ७; ३. ३६, ३; ६. ४४, ७; १०. २७, १९.
नवे ४. ३२, २३.
नवेदसः ५. ५५, ८; १०. ३१, ३.
नवेदसा १. ३४, १.
नवेदाः १. ७९, १; १६५, १३; ४. २३, ४; ५. १२, ३.
नवेन १. ३१, ८; २. १८, ३; ६. ५०, ६.
नवेभिः ४. २०, ५.
नव्यः १. ६१, १३; ६२, ११; १०५, १५; १८९, २; ५. १२, ३; ६. २०, १०; ७. ४, ८; १८, ५; ८. ३, १३; ११, १०; ९. ९४, ३; १०. ४, ५.
नव्यं १. १०, ११; ६२, १३; १०५, १२; १०९, २; १३९, ८; १४१, १०; १८०, १०; १९०, १; २. १७, १; ३. ३१, १९; ५३, १६; ४. १६, २१; ६. १, ७; १७, १३;

७. ८०, २; ९१, २; ८. १६, १; २४, २६; ६७, १८; १०. ८९, ३.
नव्यंऽनव्यं १. १५९, ४; १०. ९६, ११.
नव्यंसः ६. ६२, ४; ८. २४, ८; ५०, ९.
नव्यंसा २. ३१, ५; ६. ६, १; ४८, ११; ६२, ५; ८. ३९, २.
नव्यसि ३. ६१, ३.
नव्यंसी १. ६०, ३; १३९, १; ३. ६२, ७; ६. ८, १; ८. ७४, ७; १०. ४, ६.
नव्यंसी इति ३. ५, ७.
नव्यंसीः १. १२४, ९.
नव्यंसीनां ५. ५३, १०; ५८, १.
नव्यंसीभिः ४. ४१, १०; ६. ४९, १; ७. ५३, २; ८. ५, २४.
नव्यंसीं १. १४३, १; ५. ४२, १३; ६. ८, ५.
नव्यंसीषु १. १४१, ५.
नव्यंसे २. ३१, ७; ३. २, १३; ३२, १३; ५. ११, १; ६. ७१, ३; ८. ७, ३३; २७, १०; ९. ९, ८; ८२, ५; ९१, ५.
नव्यंस्या ६. २२, ७; ८. ५१, ३.
नव्या ५. २९, १३.
नव्यांसं १. २७, ४.
नव्यांसि १. ३८, ३.
नव्याः १. १७४, ८; ५. २९, १५.
नव्याःऽनव्याः ३. ५५, १६.
नव्ये ४. २०, १०.
नव्येभिः १. १३०, १०; ७. ९३, ४.
नव्येषु १. १३४, ४.
नव्यौ १०. ३९, ५.
नशंत् ४. २३, ४; ६. २, ५; ८. ६१, १२.
नशत् १. ४१, ५; १६४, २२; २. ४१, ११; ७. ३२, २१; ८. १९, ६; २०, १६; ३१, १७; ४७, १; ६८, ८; ७०, ३.
नशंते १. १६५, ९.
नशते ५. ४, ११; ६. ३, १; २; ७. ८२, ७.
नशथ २. १४, ८.
नशंन् ९. ७९, १.
नशन् २. २३, ८; २७, १४; ३५, ६.
नशंत १. १२३, ११; ७. १, २२; ९. ७९, १; १०. ११५, ४; १३३, ३.
नशंति ६. २८, ३; १०. २७, २०.
नशामहै २. ३०, ११; १०. ३६, ११.
नशायथः १०. ४०, ६.
नशीमहि ८. ६, ९; १०. ३६, ३; ५७, २.
नश्य १०. ९७, १३.
नश्यतः १. १२०, १२.
नश्यति १. १७०, १; १०. ९७, ११.
नश्यतु ८. २७, १८.
नश्यसि १०. १४६, १.
नष्टं १. २३, १३; ६. ५४, १०; ८. ७९, ६; १०. ४६, २.
नष्टंऽइव १. ११६, २३.
नसंते ९. ६८, ४; ७१, ३; ८.
नसते ९. ८२, ३.
नसंत १. १८६, ७; ४. ५८, ८; ८. ७२, १४; ९. ८९, ३.
नसीमहि २. १६, ८.
नसोः ५. ६१, २.
नहंना १०. ६७, ३.
नहि १. १०, ८; १९, २; २२, ४; २४, ६; ३९, ४; ५४, १; ५७, ४; ८०, १५; १२९, ४; १३८, ४; १६४, ११; १७; १६७, ९; १७९, २; २. २८, ६; ४. १८, ४; ३१, ९; ५५, ७; ५. ३१, २; ४०, ९; ६. १६, १८; २५, ५; २७, ३; ७. ४, ८; २३, २; ३२, १९; ५९, ३; ४; ८. ३, १३; ७, २१; २१, ७; २४, १२; १५; ३०, १; ३३, १६; ४०, २; ४६, ११; ६०, १४; ६४, २; ६६, १३; ७१, २; ८०, १; ८१, ३; १०२, १९; १०. २७, १८; ७१, ६; ८६, ११; ९५, १३; १०७, ३; ११९, ६; ७; १३१, ३; १४२, १; १४५, ४; १८५, २.
नहुंःऽतरः १०. ४९, ८.
नहुंषः १. १२२, ८; १०; ११; ७. ६, ५; ८. ८, ३; १०. ४९, ८; ८०, ६; ९९, ७.
नहुंषस्य १. ३१, ११; ५. १२, ६.
नहुंषा ६. २६, ७.
नहुंषे ८. ४६, २७.
नहुष्यंस्य १०. ६३, १.
नहुष्याणि ९. ८८, २.
नहुष्येभिः ९. ९१, २.
नह्यतन १०. ५३, ७.
नह्यंति १०. ६०, ८.
नह्यामि १०. १६६, ३.
नाकंः १०. १२१, ५.
नाकं १. ३४, ८; ६८, ५; ८५, ७; १३९, ४; १६४, ५०; ३. २, १२; ५, १०; ४. १३, ५; ५. १, १; १७, २; ५४, १२; ८१, २; ६. ८, २; ४९, १२; ७. ५८, १; ८६, १; ९९, २; ८. ४१, ८; १०. ९०, १६; ११३, ४.
नाकंस्य १. १९, ६; १२५, ५; ८. १०३, २.
नाके ९. ७३, ४; ८५, १०–१२; १०. १२३, ६; १३०, २.
नाथितः १०. ३४, ३.
नाथितासंः ७. ३३, ५.
नादे १०. ११, २.
नाधः २. ३५, १.
नाधमानं १. १८१, ७; २. ३३, ६; ४. १६, ९; २९, ४; ८. ७, ३०.
नाधमानस्य १. १२६, २; १७८, ३; २. १२, ६.
नाधमानाऽइव ५. ७८, ४.
नाधमानाः १. १०९, ३; ११०, ५; ११८, १०; १०. ७३, ११.
नाधमानान् १०. ११२, १०.
नाधमानां १०. १८३, २.
नाधमानाय १०. २९, ४; ५. ७८, ६; १०. ११७, ५.
नाधसी इति १०. ६५, ५.
नाधितः १. १८२, ७.
नाधितायं १. ११८, ८.
नानंदत् १. १४०, ५; ८; ३. २, ११; ९. ७०, ६.

नानंदतं १०. ६७, ९.
नानंदति ८. २०, ५.
नानदति १. ६४, ८.
नानंदतऽभिः १. ३०, १६; ६. ६, २.
नाना १. १०२, ५; १४६, ४; २. १२, ८; ३८, ५; ३. ५४, ६; ५५, ११; ५. ७३, ४; ६. १४, ३; ८. १, ३; १५, १२; ६८, ५; १०. ६७, १०; ७९, १.
नानाऽधियः ९. ११२, ३.
नानानं ९. ११२, १.
नानाऽरथं ३. ६, ९.
नानाऽसूर्याः ९. ११४, ३.
नांचं १. ३४, ४.
नांचें १. १४५, ४.
नाभः ९. ७४, ६.
नाभयः १. १३९, ९; ९. ७३, १.
नाभा १. ४३, ९; १३९, १; १४२, १०; १४३, ४; २. ३, ७; ३. ४, ४; ५, ५; ९; २९, ४; ८. १२, ३२; १३, २९; ९. १०, ८; १२, ४; ७२, ७; ७९, ४; ८२, ३; ८६, ८; १०. १, ६; ६२, ४; ६४, १३.
नाभाकस्य ८. ४१, २.
नाभानेदिष्ठः १०. ६१, १८.
नाभिः १. ५९, १; २; १०४, ४; १०५, ९; १६३, १२; १६४, ३३–३५; ४. १०, ८; ४४, ५; ५८, १; ६. ४७, २८; ८. १०१, १५; ९. ७४, ४; १०. १०, ४; ४६, ३; ६१, १८; १९.
नाभिःऽइव ८. ४१, ६.
नाभिना ६. ३९, ४.
नाभिं १. १८५, ५; २. ३, ९; ४०, १; ४; ३. १७, ४; ५. ४३, ८; ४७, २; ६. ७, २; ९. १०, ८; १०. ५, ३; १२४, २.
नाभौ १०. १३, ३; ८२, ६.
नाभ्याः १०. ९०, १४.
नाम १. ६, ४; २४, १; २; ४८, ४; ५३, ७; ५७, ३; ६८, २; ८४, १५; १०३, ४; १०८, ३; १२३, ४; ९; १२; १५५, ३; १५६, ३; १६४, ३; १८५, १; १९१, १३; २. २०, ६; २७, १५; ३३, ८; ३५, ११; ३७, २; ३. ५, ६; २०, ३; २६, ७; ३८, ४; ५४, ७; १६; १७; ५६, ४; ४. १, १६; ३९, ४; ५८, १; २; ५. ३, २; ३; १०; ३०, ५; ३३, ४; ३७, ४; ४४, २; ८; ५७, ५; ६. ४४, ८; ४८, २१; ६६, १; ५; ७५, ८; ७. २२, ५; ३२, १७; ५६, १०; ५७, १; ८७, ४; १००, ३; ५; १०३, ६; ८. ११, ५; २०, १३; ४६, १४; ८०, ९; ९. ७५, २; ८६, २०; ८७, ३; ९२, २; ९५, २; ९६, १६; ९९, ४; १०९, १४; १०. १२, ६; २३, २; २८, १२; ३९, १; ४५, २; ४९, २; ३; ५४, ४; ५५, १; ६१, १४; ६४, १; ६८, ७; ६९, ५; ७३, ८; ८४, ५; ८६, २३; ९७, ९; ११५, २; १२३, ४; ७; १४५, ४; १८१, १.

नामऽधाः १०. ८२, ३.
नामऽधेयं १०. ७१, १.
नामऽभिः १. १५५, ६; १६१, ५; १८१, ४; ३. ३८, ७; ५. ४३, १०; ५२, १०; ७. ५७, ६.
नामानि १. ७२, ३; ८७, ५; १६१, ५; ३. ३७, ३; ५. ५, १०; ४४, ४; ७. ५६, १४; ८. ४१, ५; ९. ७५, १; १०. ५, २; ६३, २; ७४, ६; १६९, २.
नाम्ना ६. १८, ७; १०. ७७, ८.
नायं ६. २४, १०; ४६, ११.
नाराशंसी १०. ८५, ६.
नाराशंसेन १०. ५७, ३.
नारि १०. १८, ८.
नारिऽभ्यः १. ४३, ६; ८. ७७, ८.
नारिषु १०. ८६, ११.
नारी १. २८, ३; ७३, ३; ४. १६, १०; ७. २०, ५; ८. १, ३४; १०. ८६, १०.
नारी इति १०. ९३, १.
नारीः १. ९२, ३; २. ३५, ५; ७. ५५, ८; १०. १८, ७.
नारीं १०. ८०, १.
नार्मरं २. १३, ८.
नार्मिणीं १. १४९, ३.
नार्यस्य ८. २४, २९.
नार्सदं १०. ६१, १३.
नार्सदाय १. ११७, ८.
नाळीः १०. १३५, ७.
नावः १. १८२, ६; ५. ५४, ४; ६. ५८, ३; ९. ७३, १.
नावः १. २५, ७.
नावं १. ११६, ५; १३१, २; १४०, १२; २. १६, ७; ४२, १; ५. ४५, १०; ७. ८८, ३; ८. ४२, ३; ७५, ९; ९. ८९, २; १०. ४४, ६; ६३, १०; १०१, २; १०५, ९; ११६, ९.
नावं ८. २५, ११.
नावंऽइव १०. १७८, २.
नावया १. ९७, ८.
नावा १. ४६, ७; ५. ४, ९; ६. ६८, ८; ७. ६५, ३; ८. १६, ११; १८, १७; ९. ७०, १०; १०. ५६, ७.
नावाऽइव १. ९७, ७; ९९, १; २. ३९, ४; ३. ३२, १४; ५. २५, ९.
नावाः ९. ४५, ५.
नावि ७. ८८, ४; १०. १३५, ४.
नाव्याः १. ८०, ८.
नाव्यानां १. ३३, ११; १२१, १३.
नाशय १. ५०, ११.
नाशयध्यै ८. ९७, १४.
नाशयामसि १०. १६२, ३.
नासत्या १. ३, ३; ४६, ५; ११६, ४; १८०, ९; १८४, १; ३; ३. ५४, १६; ५८, ७; ४. ३७, ८; ५. ४६, २; ७३, ६; ७४, २; ७५, ७; ६. ११, १; ५०, १०; ६३, १; ४; ७. ३९, ४; ७२, ३; ७३, २; ७४, ५; ८. ५, ३२; ३५; १९, १६; २५, १०; ४२, ४; १०. २४, ४; ७३, ४; १४३, ५.
नासत्या १. ३४, ७; ९–११; ४७, ७; ९; ११६, २; ९–११; १३; १४; १६; १७; १९; २०; २२; २३; ११७, १; ६; ११; १३; २३; ११८, ४; ११; १८२, ४; १८३, ३; ५; १८४,

५; २. ४१, ७; ४. १४, १; ४३, ७; ४४, ४; ६. ६३, ७; १०; ७. ६७, ३; ७१, ४; ६; ७२, १; २; ५; ८. ५, २३; ९, ६; ९; १५; २२, ५; २६, २; ५७, १; ४; ८५, १; ९; १०१, ७; १०. ३९, ३; ५; ४१, २.

नासत्याऽइव १. १७३, ४; ९. ८८, ३.

नासत्याभ्यां १. २०, ३; ११६, १; ५. ७७, ४.

नासत्याय ४. ३, ६.

नासत्यौ १०. २४, ५; ६१, १५.

नासत्यौ १. १८२, ८; ८. ८, १५.

नासाऽइव २. ३९, ६.

नासिकाभ्यां १०. १६३, १.

नाहुषा ५. ७३, ३.

नाहुषाणि ६. २२, १०.

नाहुषाय ७. ९५, २.

नाहुषीषु १. १००, १६; ६. ४६, ७; ८. ६, २४.

नि १. ५, १; ८, २; १७, ६; २२, ८; १७; २५, १०; १३; २६, २; २७, ३; २८, ९; २९, ३; ३०, १९; २२; ३३, ३; १२; ३६, १४; १९; ३७, ३; ७; ४३, ७; ४४, ११; ४५, ७; ४७, १०; ५०, १२; ५१, ६; ५२, १५; ५३, १; ६; ९; ५४, ५; ५६, ३; ५८, १; ६०, २; ६४, ४; ६७, ३; ७०, ३; ७२, १; १०; ७३, ४; ७६, २; ४; ८०, ३; ६; ८१, ४; ८९, २; ९१, १५; ९२, १६; ९९, १; १००, १८; १०१, २; १०४, १; १०५, १०; १०६, ७; ११२, २४; ११३, १७; ११४, ४; ५; ११७, ९; २०; १२२, ९; १२४, ७; १२५, १; १२७, ४^{२}; १२८, १; ८^{२}; १२९, ५; १३०, ४^{२}; ८; १३३, ५; १४०, २; १४१, ५; १४३, १; ५; १४५, ५; १४६, २; १४८, १; ४; १५५, ३; १६१, ४; १६४, २९; ३८^{२}; १७१, १; १७४, ७; १८०, ६; १८६, ११; १९१, १; ३; ४^{४}; ७; २. २, ३; ९, १; ११, ८^{२}; १०; १८; २०; १३, ६; १४, ७; १७, ६; १८, ३; २०, ८; २३, ८; १२; २४, २; ३३, ११; ३६, ३; ४; ३८, ३; ४; ४१, १३; ३. १, १०; १८; ४, ४; ७; ६, ३; ९, ९; १४, २; २३, ४; २७, १०; २९, ४; १४; ३०, ९; १६; १९; ३१, ९; ३३, ८; १०; ३८, ३; ७; ४५, १; ५१, ११; ५५, ९; १३; १७; ४. ३, २; ४, ४; ६, २; ११; ७, ५; ९, ३; ४; १६, ९; १०; १२; १३; १७, १४; १९, ४; २६, १; २८, २–४; ३०, १०; ३८, ६; ४१, ४; ४४, ५; ४७, ४; ५०, ३; १०; ५६, ४; ७; ५७, ७; ५. १, ५; ६; २, ६; ४, ३; ८, २; ११, २; २१, १; २२, २; २८, २; २९, १०; ३२, ४; ८; १०; ३५, ५; ४०, ७; ४१, १०; १५; ४२, १०; ५२, ११; १७; ५३, ९; ५४, ५; ५६, ४; ५७, ३; ६०, २; ६६, ४; ७२, १; ३; ७५, ५; ८०, ६; ८३, ८; ६. १, २; ६; ६, ६; ८, ५; १५, ८; १२; १५; १६, १०; २८; ४१; १७, ६; ९; १८, १०; १३; २८, २; २९, ६; ३०, ३; ३४, ४; ४५, ८; २३; ५१, १४; ५२, १; ५६, ३; ५९, ६; ६१, ३; ६५, ३; ४; ६७, ४; ७२, ४; ७. १, २; ११; ३, ७; ८; ४, ३; ४; ५, ६; ९; ६; ३; ११, १; १५, ७; १८, ११^{२}; १२; १४, १८; २४; १९, २; ४; ८^{२}; २०, ४; २१, १; २; २५, २; २६, ३; २७, ४; ३०, ३; ३२, १; ३७, ३; ६; ३८, ३; ५; ४०, ६; ५५, २; ७; ५६, १९; ५९, ७; ६८, ५; ६९, ५; ६; ७०, ३; ४; ७१, ५; ७३, २; ७४, २; ८२, ८; ९२, ३^{२}; १०४, १^{३}; ५; १०; ८. २, २६; ४, ५; ५, १३; ६, १४; १६; ७, २; ५^{२}; ३४^{२}; १२, १; ९; १३, २४; १७, १३; १९, ३३; २१, १५; २३, १४; १७; २६; २४, २५; २५, ८; ९^{२}; ११; २७, १२; ३२, ३; ३३, ८; ३५, २२; ३९, २^{२}; ४१, ३; ८; ४४, ११; ४६, २३; ४८, १०; ५०, ८; ५२, ७; ५४, ८; ६१, २; १६; १८; ६४, २; ७०, १०^{२}; ७२, २; ७५, १; ७८, ६; ८२, ४; ८४, २; ८७, २; ९५, ८; ९६, ११; ९७, ८; १००, ७; १०१, १४; १०२, १४; १८; ९. ६, ८; १९, ७^{३}; ३६, १; ५२, ४; ५५, २; ५९, ३; ६३, २; २३; ६८, २; ७०, ७; ८; ७१, २; ७३, ४; ७९, ५; ८६, ६; ८७, १; ८९, १; ९८, ५; ९९, ९; १०४, १; १०७, १९; १०९, २२; १०. ५, २; ७, ५; ८, ३; १०, ३; ८; ११, २; १६, १२; १८, ११; १९, १; २^{३}; ३^{२}; ५; ६; ८^{२}; २१, ७; २२, १४; २७, २; २८, ६; ८; २९, १; ३०, १४; १५; ३३, २; ३४, १४; ३७, २; ३; ९; १२; ३९, ७; १४; ४०, ४; १२; १४; ४२, १; ५; ६; ८^{२}; ४३, २; ४४, ६; ४६, ६; ४८, ४; ४९, ८; ५२, २; ५३, १; ५६, ४; ५; ६०, ६; ६१, ७; ६३, १६; ६५, ७; ६६, ९; ७०, ३; ६; ७३, ६; ८१, १; ८४, ७; ८७, ७; ११; १२; ८९, ९; ९४, ३; ५; ९५, १७; ९६, ३; ९८, ४; १०१, १; ११; १०२, ५; १११, ४; ११२, ९; ११४, २; ३; ९; ११६, ५; ११८, १; ११९, ९; १२०, १; ७; १२२, ८; १२४, ९; १२७, ४; ५^{४}; १२८, ४; १४२, २; ६; १४६, ५; १४९, ४; १६०, १; १६६, ३; १६८, ३; १७७, २.

निऽअंचनं ८. २७, १८.

निऽअयनं १०. १९, ४; १४२, ७.

निऽअर्थे ७. १८, ९; १०. १०७, ८.

निऽअर्थात् १०. १२८, ७.

निऽअर्थानि ६. २७, ६.

निऽइतः १०. १६१, २.

निऽईक्षण १. १६२, १३.

निऽउंसाः १०. ५७, १७; ३४, ५; ९.

निऽऊहतुः १. ११६, १.

निऽऊहथुः १. ११२, १९.
निऽऋंजते १. ५४, २.
निऽऋंजसे ८. ९०, ४.
निऽऋपंति १. ५२, ७.
निऽऋंष्टः १०. १०८, ७.
निऽऋंष्टं ४. १८, ५; २०, ६; १०. ४२, २.
निऽगुरिरे ४. १, १^{2}; ८. १९, १८; २१.
निऽओंकसे १. ९, १०.
निऽओंकाः ५. ४४, १४.
निऽओचंनी १०. ८५, ६.
निंमृत १०. ७४, २.
निंसंते १. १४४, १.
निंसते ९. ८५, ३; १०. ९२, २; ९४, ९.
निंसानं ८. ४३, १०.
निः १. ४, ५; ३३, ५; ९; १०; ३४, ११; ५१, ११; ५६, ५; ८०, १; २; ४^{2}; १०; ८५, ९; ९५, ४; १०३, २; १०४, ८; १०६, १–६; ११०, ८; ११५, ६; ११६, २१; ११७, १४; १५; ११८, ६; ८; १२०, १२; १४१, ३; १३; १५७, ४; १६१, ७; १६२, १२; १६३, २; १७९, ४; २. ११, ९; २३, १८; ३. ३१, ४; ८; ४. १८, २^{2}; १९, १; ९; २७, १; ३६, ४; ५८, ४; ५. १, २; ३१, ९^{2}; ३२, ३; ५५, १०; ८७, ४; ६. १६, १३; ३५, ५; ४७, ३०; ६२, ६; ६६, ४; ७. १, ४; ३, ९; ५०, ३; ५६, २१; ६८, ७; ७१, ५; ८. १, १७; ३३; ३, १९^{3}; २०^{4}; ४, २०; २१, १६; ४८, ११; ७७, ६; ७९, २; ८१, ६; ९. ७२, ८; ९४, ४; १०८, ६; ११०, ८; १०. ८, ८; १६, १३; २४, ४; २८, ४; ३४, ९; ३९, ४; ५५, ८; ६०, ७; ६१, ७; ६२, ७; ६५, १२; ६७, ५; ६८, ३; ८; ९; ७६, ७; ८०, ३; ९७, ९; १०१, ५; १०३, १२; १०७, १; १२४, ७; १२६, २; १२७, ३; १२९, ४; १३५, ५; १६०, ४; १६२, २.

निःऽअजे ३. ३०, १०.
निःऽअतक्षत १. १६४, २३; ३. ६०, २.
निःऽअतंतसत १. १२०, ७.
निःऽअमंथत १०. २४, ४.
निःऽअयंनं १०. १३५, ६.
निःऽअंष्टाः १. ३३, ६.
निःऽअहंन् १. १०१, १.
निःऽऊहथुः १. १८२, ५.
निःऽऋंतं १. ११९, ७.
निःऽऋंतिः १. ३८, ६; ५. ४१, १७; ७. ३७, ७; १०. १०, ११; ३६, २; ५९, १.
निःऽऋंतिं १. २४, ९; १६४, ३२; ६. ७४, २; १०. ३६, ४; ७६, ४.
निःऽऋंतीः १०. ११४, २.
निःऽऋंतीनां ८. २४, २४.
निःऽऋंतेः १. ११७, ५; ७. ५८, १; १०४, ९; १०. १८, १०; ९५, १४; १६१, २.
निःऽऋंत्याः १०. १६५, १.
निःऽऋंत्यै १०. १६४, १.
निःऽऋथं ७. १०४, १४.
निःऽएतवे १. ३७, ९; ८. ४५, ३०.
निःऽएहि १०. १२४, ६.
निःऽएतु ५. ७८, ७; ९.
निःऽकृण्वानाः १. ९२, १.
निःऽकृतं १. २०, ६.
निःऽकृतं १. २, ६; १२३, ९; ३. ५८, ९; ६२, १३; ५. ६७, १; ८. ८०, ७; ९. १३, १; १५, १; ६१, २५; ६४, १५; ६९, ४; ७१, २; ७८, १; ८६, ७; १६; ३२; ९३, २; १०१, १६; १०७, २२; १०. ३४, ५; ४०, ६; ६५, ६; ९४, ५.
निःऽकृतिं १०. १६५, १.
निःऽकृतीः १०. ९७, ९.
निःऽजगन्वान् १०. १, १.
निःऽततक्षतुः ८. ६१, २.
निःऽततक्षुः १०. ३१, ७.
निःऽतंसा २. २३, ११.
निःऽतुरः ८. ७७, २.
निःऽतुरे ८. ३२, २७.

निःऽनिक् ५. ६२, ४; ९. ७०, ७.
निःऽनिजः ७. ६४, १; १०. २७, २४.
निःऽनिजं १. २५, १३; ११३, १४; ८. १९, २३; ९. १४, ५; ६८, १; ७१, २; ८२, २; ८६, २६; ४६; ९५, १; ९९, १; १०७, २६; १०८, १२.
निःऽनिजा १. १६२, २.
निःऽनिजानः ९. ६९, ५.
निःऽनिजे ९. ६९, ५; ७०, १; ७१, १; १०. ४९, ७.
निःऽपतंत्योः १०. २४, ५.
निःऽपदः १०. १०२, ६.
निःऽमंजा ८. ४, २०.
निःऽमंथितः ३. २३, १; २९, १२.
निःऽमंथंतः १०. १८४, ३.
निःऽमायाः १०. १२४, ५.
निःऽयुवानः ४. ४८, २.
निःऽशसा १०. १६४, ३.
निःऽसहंमानः १. १२७, ३.
निःऽसिधः १. १६९, २; ३. ५१, ५; ६. ४४, ११.
निःऽसिधे ३. ५५, ८.
निःऽसिधां ४. २४, १.
निःऽसिध्वरीः ३. ५५, २२; ८. ५९, २.
निःऽसृजः १. १३१, ३^{2}.
निःऽस्थाः ९. ११०, ९.
निःऽस्थां ३. ३१, १०.
निःऽस्थितः १. १८२, ७.
निऽकर्तवे ८. ७८, ५.
निऽकामः ३. १, १५; ४. १६, १०; १०. ९६, ३.
निकामऽभिः १०. ९२, ९.
निऽकामं ६. १७, १०.
निऽकामाः ९. ९७, ३७.
निऽकामाः ९. ११३, १०.
निऽकामासः १०. २५, ५.
निऽकामैः ४. १६, ६; १०. ७३, ६.
निऽकिल्बिषं १०. १०९, ७.
निऽकुर्वानः १०. ३४, ७.
निक्तः ८. २, २; ९. १०९, १०.
निक्तं ९. ६९, ४.
निक्तऽहस्तः ६. ४५, ५.

निक्तैः ९. ९३, ३.
निऽक्रमणं १. १६२, १४.
निऽखातं १. ११७, ५; १२; ८. ६६, ४.
निऽगच्छात् १०. १०, ११; १२.
निऽगतान् १०. १३२, ५.
निऽगुतः ९. ९७, ५४; १०. १२८, ६.
निऽगूळ्हं ६. ४४, २३.
निऽगूळ्हाः १०. १०८, ११.
निऽग्रभे ८. २३, ३.
निऽघनिघ्नते १. ५५, ५.
निऽघोषयः ८. ५०, ८.
निऽघोषयन् ८. ५१, ८.
निऽचंक्रया ८. ७, २९.
निऽचाय्यं १. १०५, १८; ३. २६, १.
निऽचिक्यत् ४. ३८, ४.
निऽचितः २. १२, १३.
निऽचिरा ८. २५, ९.
निऽचिराभ्यां १. १३६, १.
निऽचिरासः ३. ९, ४.
निऽचुंपुणः ८. ९३, २२.
निऽचेतारः ७. ५७, २; १०. ६१, २७.
निऽचेतारा १. १८४, २.
निऽचेरुः १. १८१, ५.
निऽजघंथ १. ५२, ६.
निऽजघ्निः ९. ५३, २.
निऽजुरः २. २९, ६.
निऽजूर्वति १०. १८७, ३.
निऽजूर्वथः ७. १०४, ४.
निऽजूर्वन् ४. ७, ११.
निऽजूर्वाः २. ३०, ५.
निऽजूर्वात् २. ११, १०.
निणिक् ४. ५, ८.
निण्यः १. १६४, ३७.
निण्यं १. ३२, १०; ९५, ४; ४. १६, ३; ७. ३३, ९.
निण्या ४. ३, १६; ७. ५६, ४.
निण्यानि ७. ६१, ५.
निण्ये ९. ९२, ४.
निण्योः १०. ५, १.
निऽतिक्ताः १०. १११, ९.
निऽतिक्ति ६. ४, ५.
निऽतोदिनः १०. ३४, ७.
निऽतोशनं ६. १, ८; १०. ६०, २.
निऽतोशना ८. २५, २३.
निऽतोशनासः ७. ९२, ४.
निऽतोशे ४. ३८, १.
नित्यंऽअरित्रां १. १४०, १२.
नित्यः १. ६६, १; ३; १४०, ७; १४१, २; ३. २५, ५; ७. १, २; ८८, ६; १०. १२, २; ३१, ४.
नित्यं १. ७१, १; ७३, ४; १६६, २; १८५, २; ३. १५, २; ५३, २४; ५. १, ७; ८५, ७; ७. १, १२; ८. ४, १८; ९. ९२, ३; १०. ३९, १४.
नित्यया ८. ३१, ५; ७५, ६.
नित्यऽस्तोत्रः ९. १२, ७.
नित्यस्य ४. ४१, १०; ७. ४, ७.
नित्यऽहोता १०. ७, ४.
नित्या ७. १, १७.
नित्याः २. २७, १२.
नित्यात् ८. ५६, २.
नित्यासः १. १४८, ५; ५. ६, १.
नित्ये १. १४८, ३; २. २, ११; ७. १, २१.
नित्येन ४. ४, ७.
निदः १. ४, ५.
निदः १. २४, ४; १२९, ६; २. ३४, १५; ४. ४, १५; ५. ५३, १४; ८७, ६; ९; ६. १४, ५; ६१, ११; ७२, १; ७. १६, ८; ८. ७८, ६; ९. २९, ५; ६१, ३०; ७०, १०.
निऽदधत् १०. १८, १३.
निऽदुधिरे ८. १९, १७.
निऽदुधुः ५. ३२, १२.
निदंऽनिदं ९. ७९, ५.
निऽदातारं ८. ७२, ५.
निऽदाने ६. ३२, २; १०. ११४, २; १३०, ३.
निऽदानाः ४. ५, १२.
निदायाः ६. १२, ६.
निऽदितं ५. २, ७.
निऽदिता ८. १०३, ११.
निदे २. २३, १४; ३४, १०; ३. १६, ५; ४१, ६; ७. ३१, ५; ७५, ८; ९४, ३; ८. ८, १३.
नियमानान् ६. ५२, ३.
निऽद्रा ८. ४८, १४.
निऽधयः १. १८३, ४.
निऽधया ९. ८३, ४.
निधयाऽइव १०. ७३, ११.
निऽधातुः ५. ३०, २.
निऽधातोः १. ४१, ९.
निऽधाने ३. ३१, २; ५३, ५.
निऽधाना १. १६३, ५.
निऽधान्यं ८. ७२, १८.
निधाऽपतिः ९. ८३, ४.
निऽधायि ४. २, १; ५. ३, ३.
निऽधारयः ८. ४१, ४.
निऽधारयंतः ४. २, १२.
निऽधिः ७. ६७, ७; १०. १०८, ७; १८६, ३.
निधिऽभिः १०. १७९, २.
निऽधिं १. १३०, ३; २. २४, ६; ५. ४३, ८; ७. ६९, ३.
निधिऽमत् १०. ५९, २.
निधिऽमंतं २. ३९, १.
निधिंऽइव १. ११६, ११.
निऽधिषु १०. १५, ५.
निऽधीन् १०. ६८, ६; १०८, २; १३८, ४.
निऽधीनां ८. २९, ६.
निधीयमानं १०. ३२, ६.
निऽध्रुवि ८. २०, २२.
निऽध्रुविः ७. ३, १; ८. २९, ३.
निऽनद्धः ६. ७५, ५.
निऽनमे ३. ५६, १.
निनाय १०. ६८, २; १०९, २.
निनिक्त १०. १३२, ६.
निनित्सात् ६. ५२, २.
निनित्सुः ८. ६८, १९.
निनित्सोः १. १८९, ६; ७. २५, २; ३४, १२.
निनिदुः १०. २७, ६.
निनीयात् ७. ८८, २; १०. ८५, २३.
निनीषसि ८. १०३, ४.
निनेथं ७. २८, ३.
निनेथ ६. १८, १३.
निंदुत ४. ५, २.

निंदंति १०. ४८, ७.
निंदात् ५. ४२, १०.
निंदितऽअश्वः ८. १, ३०.
निंदिता ३. ३९, ४.
निंदितारः ५. २, ६.
निंदिम १. १६१, १.
निंद्यासः ५. २, ६.
निन्यथुः १. ११६, ८; २४.
निऽपद्यते १०. १६२, ५.
निऽपातः ४. ५५, ३.
निऽपाति १. ७३, २; ७. १, १५.
निऽपादाः ५. ८३, ७.
निऽपासि ४. ११, ६.
निऽपूतः ८. १७, ११.
निऽपूतं २. १४, ९.
निऽबर्हयः १. ५३, ७.
निऽबाधितं १. ११९, ८; ७. ८३, ६.
निऽबाळ्हः १. १०६, ६.
निऽबोधात् २. ३०, ७.
निऽबोधिपत् २. १६, ७.
निऽभृतं १. १०२, ५; २. १४, १०.
निऽमिता ५. ६२, ७.
निमिताऽइव ३. ३०, ४.
निऽमितासः ३. ८, ७.
निऽमिम्युः ३. ८, ६.
निऽमिश्लः ६. २३, १; ८. ९६, २.
निऽमिश्लां १. १६७, ६.
निऽमिषः २. २८, ६; ८. ७३, २.
निऽमिषतः १०. १२१, ३.
निऽमिषि १. ७२, ५; २. ३८, ८.
निऽमृग्राः २. ३८, २.
निऽमृजंतः १०. १२२, ७.
निऽमेघमानः ८. ४, १०.
निऽमेघमानाः २. ३४, १३.
निम्नं १. ३०, २; ४. ३३, ७; ४७, २; ५. ५१, ७; ८. ३२, २३; ९. ९७, ४५.
निम्नाऽइव १. ५७, २.
निम्ने ९. ६९, ७.
निम्नेनऽइव ९. १७, १.
निम्नैः १०. ७८, ५; १४८, ५.
निऽम्रुचः १. १५१, ५; १६१, १०.
निऽम्रुचि ८. २७, १९; १०. १५१, ५.
निऽयतं ४. ३, ९.
निऽयता १०. २७, २२.
निऽयंता ८. ३२, १५.
निऽययिनं १०. ६०, २.
निऽयवं १०. ३०, १०.
निऽयानं १. १६४, ४७; १०. १९, ४; १४२, ५.
निऽयुतः १. १३४, २; १३५, २; १६७, २; १८०, ६; ३. ३१, १४; ३५, १; ४. ४१, १०; ४७, ४; ५. ५२, ११; ६. ३५, ३; ३६, ३; ४७, १४; ४९, ४; ७. १८, १०; २३, ४; ७२, १; ९०, १; ३; ९१, ५; ६; ९२, १; १०. २६, १.
निऽयुतं १. १२१, ३.
निऽयुतं १. १३८, ३.
निऽयुता १. १३५, १; ७.
निऽयुता ७. ९१, ३.
नियुत्ऽभिः १. १३५, ३; ३. ५८, ७; ४. ३१, ४; ६. २२, ११; ४५, २१; ६२, ११; ७. ९२, ३; १०. ३, ६; ८, ६.
निऽयुत्ऽरथः १०. २६, १.
नियुत्वः १. १०१, ९; ८. १०१, १०.
नियुत्वंतः २. ४१, ३.
नियुत्वंता १. १३४, १; ४. ४७, १.
नियुत्वते १. १३५, १.
नियुत्वंतः ५. ५४, ८.
नियुत्वंता ४. ४७, ३.
नियुत्वान् १. १३५, ४; २. ४१, १; २; ३. ४९, ४; ४. ४६, २; ४८, २; ६. ४०, ५; ६०, २; ७. ३९, २; ८. ९३, २०; ९. ८८, ३; ८९, ६.
निऽयुवाना ७. ९१, ५.
नियुवैते इति निऽयुवैते ७. ४०, २.
निऽयूयं १०. ७०, १०.
निऽयेमिरे ८. १२, २९.
निऽरण्यथः १. ११२, १८.
निरवस्यं १. १२२, ११.
निरामिणः २. २३, १६.
निऽरिणाति १. ६१, १३.
निऽरिणानः ९. १४, ४.
निऽरिणासि १०. ११६, ३.
निऽरुद्धः १०. २८, १०.
निऽरुद्धाः १. ३२, ११.
निऽरुध्य ७. ६, ५.
निऽरुंधानः १. ५३, ४.
निऽरुंधानासः १. १२२, ७.
निरेकं ८. २४, ४.
निरेके १. ५१, १४; ७. १८, २३; २०, ८; ९०, ३; ८. २४, ३; ३३, २; ९६, ३.
निऽवचनं ५. ४७, ५.
निऽवचना ४. ३, १७.
निऽवचनानि १. १८९, ८; २. ९७, २; १०. ११३, १०.
निऽवतः ३. २, १०; ७. ५०, ४; १०. १२७, २; १४२, ४.
निऽवता ८. ४५, ३८.
निवत्ऽसु १. १६१, ११.
निवनाऽइव १०. ४०, ९.
निऽवरः ८. ९३, १५.
निऽवर्त १०. १९, ६.
निऽवर्तत् १. १२१, ४.
निऽवर्तन १०. १९, ८.
निऽवर्तनं ३. ९, २; १०. १९, ४; ५.
निऽवहंता १. ११९, ४.
निऽविदः २. ३६, ६; ४. १८, ७; ६. ६७, १०.
निऽविदं १. १७५, ६; १७६, ६.
निऽविदा १. ८९, ३; ९६, २.
निऽविद्धः ४. १८, ९.
निऽविद्धा १. १६४, ८.
निऽविविध्वान् ४. १८, ९.
निऽविशंते १. १६४, २२.
निऽविष्टाः १०. ५१, ४.
निऽवृतं १. ११२, ५.
निऽवृताः १. ५७, ६; १०. ९८, ६.
निऽवेशनः ४. ५३, ६.
निऽवेशनं १०. १४२, ७.
निऽवेशनात् ४. १९, ९.
निऽवेशनी १. २२, १५.
निऽवेशनीं १. ३५, १.
निऽवेशने ६. ७१, २; ७. १९, ५.
निऽवेशयन् १. ३५, २; ४. ५३, ३; ७. ४५, १.

निऽवेशे ९. ६९, ७.
निऽशितं ४. २४, ८.
निऽशिता ७. १८, ६.
निऽशितानि १. १७१, ४.
निऽशितिं ६. २, ५; १३, ४; १५, ११.
निऽशिती ८. १९, १४.
निऽशिशानाः ७. ३, ५.
निऽशिषन् ४. २, ७.
निऽशुंभाः ६. ५५, ६.
निषंगिणः ३. ३०, १५; ५. ५७, २.
निषंगिऽभिः १०. १०३, ३.
निष्कऽग्रीवः ५. १९, ३.
निष्कं २. ३३, १०; ८. ४७, १५.
निष्कान् १. १२६, २.
निष्टिऽग्र्यः १०. १०१, १२.
निष्ट्यः ६. ७५, १९; १०. १३३, ५.
निष्ट्याःऽइव ८. १, १३.
निष्षपी १. १०४, ५.
निष्षाट् १. १८१, ६; १०. ४८, ७.
निऽसत्तः १. ५८, ३; ६८, ४; ६९, २; ७०, ४; ३. ३, २; ६, ४; ६. ९, ४.
निऽसत्तं ५. ३२, ५; १०. ७३, ९.
निऽसत्तं १. १४६, १.
निऽसत्ता १०. ७३, २; ८०, ६.
निऽसत्ताः ९. ८९, ५; १०. १५, २.
निऽसत्तिः ४. २१, ९.
निऽसत्ते १०. ८२, ४.
निऽसत्स्नुं १०. १६२, ३.
निऽसदनं १. १६२, १४; १०. ९७, ५.
निऽसदा २. २१, ५; १०. ५३, २.
निऽसदि ६. २७, १; २.
निऽसदे १. १०४, १.
निऽसद्य १. १०८, ३; १७७, ४; २. ३, ८; ३५, १०; ३. २१, १; ३५, ६; ४. ४, १२; ५. २, ७; ६. ४०, १; १०. ६, ७; १४, ५; १५, ६; ५२, १; ११२, ३.
निऽससत्थ ८. ४८, ९.
निऽससाद ७. १५, २; ८. १००, १०.
निऽसादयतः ३. १९, ५.
निसिक्तऽपां ७. ३६, ९.
निऽसिक्तं १. ७१, ८; ८. ७२, ११; १०. ६१, ६.
निऽसिंचन् ५. ८३, ६.
निऽसीदंति ७. १६, ८.
निऽसीदथः ८. ९, २१.
निऽसीदन् १. ७१, २.
निऽसीदन् १०. ८८, १९; ९८, ५.
निऽसेद ४. ३५, ८.
निऽसेदुः १. १६४, ३९; १०. ६१, १४; १०९, ४.
निऽसेदुषः १०. ८६, १६.
निऽसेवे १०. ९५, ८.
निऽस्पृक् १०. ९५, ९.
निऽस्पृशें १०. ९१, १३.
निऽस्वरं ७. १, ७; १०४, ५.
निऽहंतस्य १. १६२, ११; ६. २७, ४.
निऽहंतवे २. १३, ८.
निऽहाकया १०. ९७, १३.
निऽहितः १. १८३, ४; २. ३, १; ३. १, २०; २९, २; १२; ५. ४७, ३; ८. ५७, ४; ९. ६८, ५.
निऽहितं १. ३२, १०; १३०, ३; १६४, ७; ३. ७, ७; ३०, १४; ५. २, १; ६. ९, ५; ७५, ८; ९. ८७, ३; १०. ५, १; ७१, १; ७९, २.
निऽहिता १. १६४, ३; ५; ४५; १०. ७१, २.
निऽहिताः १. २४, ७; ७२, ६; ७. ८७, ५; ९. ७४, ६.
निऽहितासः १. २४, १०.
निहिते इति निऽहिते ३. ५५, १५; ५६, २.
नीचा २. १३, १२; १४, ४; ४. ४, ४; ३८, ५; ६. ८, ५; १०. ३४, ९; १५२, ४.
नीचात् १. ११६, २२.
नीचाऽवयाः १. ३२, ९.
नीचीं ८. १०१, १३.
नीचीः १. ६६, ५; ७२, १०; ५. ४४, ४; ६. १७, १२; ७. १८, १५; ९. ८८, ६.
नीचीनऽबारं ५. ८५, ३; ८. ७२, १०.
नीचीनऽबारे १०. १०६, १०.
नीचीनं १०. ६७, ११.
नीचीनाः १. २४, ७.
नीतां १०. १०९, ५.
नीथऽविदः ३. १२, ५.
नीथां १. १०४, ५.
नीथा १०. ९२, ३.
नीथानि ४. ३, १६.
नीथेऽनीथे ७. २६, २.
नीनमः ८. २४, २७.
नीनंशः ६. ४८, १७.
नीपऽअतिथिं ८. ४९, १७.
नीपऽअतिथौ ८. ५१, १.
नीयते १. १४१, ४.
नीयते १. १६२, ३; १६३, १२; ३. २, ७; २७, ८; ४. ९, ३; १५, १; ८. ४६, ३३; ९. १५, ३; २७, ३; १०. १७६, ३.
नीयसे ९. २४, ३; ९९, ८.
नीलऽपृष्ठः ३. ७, ३.
नीलऽपृष्ठं ५. ४३, १२.
नीलऽपृष्ठाः ७. ५९, ७.
नीलऽलोहितं १०. ८५, २८.
नीलऽवत् ७. ९७, ६.
नीलऽवान् ८. १९, ३१.
नीळं १०. ५, २.
नीळयः १०. ९२, ६.
नीळयासे ६. ३५, २.
नीळे ४. १, ११; १२; १०. ५, ६.
नीव्याभिः ६. ३२, ४.
नीहारेण १०. ८२, ७.
नु १. ८, ५; १०, ९; १७, ८; २२, ८; २५, १७; १८; ३२, १; ३९, ४; ४१, १; ४८, ३; ५२, ११; ५३, १; ५६, २; ५८, १; ५९, ६; ६४, १३; १५; ६८, ४; ७२, ८; ८०, १५; ८२, १–५; ८९, ९; ९१, ३; ९६, ७; १००, १०; १०४, २; १०५, १०; १०९, ७; ११३, ११; १२०, २[२]; १२४, १; १३२, १; ४; १३६, १; १३९, १; १४१, १०; १४५, १; १४८, ३; १५४, १; १६४, ३२; १६५, ५; ९; १०; १३; १६६, १; १६७, ९; १७२, ३; १७४, ४; १७८, २;

१७९, १; २; ५; १८६, ९; १८७, १; १९१, १०–१२; **२.** १, ६; ४, ८; ८, १; ११, ३; ४; ६; ७; १५–१७; १५, १; १८, ३; २८, ९; २९, ३; ३१, ३; ३३, ७; **३.** ६, २; १३, ७; ३१, ९; ३२, ४; ३८, २; ७; ४२, २; ४९, २; ५३, २; ५५, १; ६; १८^{२}; ५८, ६; **४.** ५, ७; ६, ७; १६, २०; २१^{२}; १८, ३; ४; २०, ४; ७; २३, ६; २७, १; ३६, २; ३९, १; ४०, १; ४४, ६; ५१, ९; ५४, १; ५५, ६; ५६, ४; **५.** १, ७; १०, ६; १५, ५; १६, ५; १७, ५; २९, १३^{२}; १४; ३०, ३; ३१, ७; १३; ३२, ९; ११; ३३, ८; ३६, ३; ३८, ५; ४१, १; १३; १७; ४५, ४; ५; ४६, ३; ५२, १५; ५६, ८; ६०, ६; ६७, ५; ७४, २; ६; ८५, ६; ८७, २; **६.** ४, ८; ८, १^{२}; ९, ६; १०, ५; १२, २; १४, १; १५, ५; १७, ९; १८, ३^{२}; ८; ११; २१, ११; २२, ५; २४, ३; २७, ३; ३०, ३; ३७, ३^{२}; ३९, ३; ५; ४४, ५; ४७, १; २२; ४८, १६; ४९, १५; ५०, ५; ५१, १२; ५२, ५; ५५, ४; ५७, १; ५९, १; ३; ६३, १०; ६६, १; ३–५; ८; ६८, ८; ९; **७.** १, २०; २५; ७, ७; १५, ४; १९, ९; ११; २०, २; ६; २२, ८^{२}; २७, ४; ५; ३२, ५; १२; ३३, ३^{३}; ३७, ४; ५; ३९, ६; ७; ४८, ४; ५६, १५; ६२, ६; ६६, ५; ६७, १०; ६८, ५; ७५, ८; ८२, ६; ८६, २; ८८, २; ४; ९०, ३; ९३, १; ६; ९६, ४; १००, १; **८.** ३, १३; १०, ३; १२, ४; २०, ८; २१, ७; २४, ११; १९; २५, २३; २७, ९; १८; ४०, ८–१०; ४५, ३७; ४६, ११; २८; ५१, ७^{२}; ६१, ११; ६३, ५; ६६, ९^{२}; ६७, १; २०; ७२, ६; ७६, १; ७७, १; ८०, ५; ८१, ८; ८५, ९; ९३, ११; ९४, १०–१२; १०१, १५; **९.** ९, ८; ११, ४; २३, ७; ४०, ३; ९२, ५; ९३, ५; ९७, ४८; **१०.** १०, ५; ११, ३; १८, ४; २३, २; ४; २७, ६^{२}; ७^{२}; २९, ६; ३०, १०; ३४, १४^{२}; ३९, ५; ५०, २; ५^{२}; ५४, ३; ५७, ३; ५९, २^{२}; ४; ६१, ५; ८; १३; २४^{२}; ६२, ६; ६९, ५; ७२, १; ७९, ६; ८६, ३–५; ८८, ३; ९२, ७; ९३, १५; ९५, १; ९६, ११; ९७, १; ९९, ६; १००, ६; १०२, १०; १११, ७; ११५, १; १३२, ३; १४७, ४; १५७, १; १६८, १; १७५, ४.

नुत्थाः **६.** १७, ५.

नुदत **१०.** १६५, ५.

नुदंत **१.** १६७, ४.

नुदस्व **९.** ५३, १; ६३, २४.

नुदस्व **३.** ४७, २; **६.** २१, ७; **७.** ३२, २५; **१०.** ८४, २; १३१, १; १८०, २.

नुदेथां **७.** १०४, १.

नुनुदे **३.** ३४, १०.

नुनुदे **७.** १८, १६; ८६, १; **८.** १४, ८.

नुनुद्रे **१.** ८५, १०; ११; ८८, ४.

नुवंत **१.** २९, ५.

नूतनः **१.** १०५, ४; **५.** ४२, ६; **१०.** ४३, ५.

नूतनं **५.** ५५, ८.

नूतनस्य **२.** २०, ४; **३.** ५१, ६; **६.** २१, ८; २७, ३.

नूतना **२.** ११, ६; **५.** ३१, ६; **७.** ९८, ५.

नूतनानि **३.** १, २०.

नूतनाभिः **६.** ४४, १३.

नूतनाय **३.** ४७, ५.

नूतनासः **६.** २१, ५; २७, १.

नूतनेन **१.** ११८, ११; **५.** ४२, १८; ७८, ४; **७.** ५१, १.

नूतनेभिः **३.** ३२, १३.

नूतनैः **१.** १, २.

नूत्नाः **७.** १८, २०; २२, ९; **८.** २१, ७.

नूनं **१.** १३, ६; २४, १; ३८, १; २; ३९, ७; ४०, ५; ८२, ३; ८४, ५; १११, ४; ११३, १०; १२४, ९; ११; १६५, १२; १७०, १; १७४, ३; १८९, ४; **२.** ११, २१; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; २८, ८; ३८, १; ३; **३.** ४७, ४; **४.** २०, २३; ३३, ११; ५१, १; **५.** २४, ४; ४२, १; १४; ५६, ५; ५८, १; ६१, १४; ६४, ३; ७०, १; ७६, १; २; **६.** १९, ४; २५, ९; ३३, ५; ३४, १; ३५, ५; ३८, ५; ४५, ११; ४८, १९; ६०, २; **७.** २६, ३; २९, ३; ३८, १; ४५, २; ६३, ४; ६७, ३; ४; १०४, २०; **८.** ४, ११; ७, २०; ८, २; ९, १; ७; ८; १४; १५; २१; १३, ५; १८, १; २०, १५; २३, २४; २४, १४; २३; २६; ३२, १६; ४६, १५; १६; ४८, ३; ४९, ७; ६६, ७; ६७, १६; ७५, ६; ८४, ७; ८६, २; ९०, ६; ९२, १६^{२}; १००, ७; १०१, १; **९.** ९९, ३; १०७, २; **१०.** १०, ४; १५, २; ५३, ९; १०; ६१, २६; ६२, ८; १०६, १; १११, ८; ११२, ८; १२६, ३; १८८, १.

नूनोत **६.** ३, ७.

नूपत **९.** १०३, ३.

नृऽग्ने **४.** ३, ६.

नृऽचक्षः **१०.** ८७, ९; १७.

नृऽचक्षसः **२.** २४, ८; **८.** ४३, ३०; **९.** ७३, ७; ८०, १; ८३, ३; ८५, ९; **१०.** ६३, ४; ८७, ८; १०७, ४; १५८, ५.

नृऽचक्षसः **३.** ५३, १०.

नृऽचक्षसं **१.** २२, ७; **८.** १९, १७; **९.** ८, ९; ८६, ३६.

नृऽचक्षसा **९.** ५, ७.

नृऽचक्षसे **४.** ३, ३; **९.** ६६, १५.

नृऽचक्षसौ **१०.** १४, ११.

नृऽचक्षाः **१.** ९१, २; **३.** १५, ३; २२, २; ५३, ९; ५४, ६; **७.**

६०, २; ८. ४८, ९; १५; ९. ४५, १; ७०, ४; ७८, २; ८६, २३; ३८; ९२, २; ९७, २४; १०. ४५, ३; ८७, १०; १३९, २.
नृऽजितें २. २१, १.
नृणां १. ४३, ७; ४८, ४; ७७, ४; २. १, १; ३. १६, ४; ५१, ४; ५२, ८; ४. २५, ४; ५. १८, ५; ३०, १२; ६. ३३, ३; ६५, ५; ७. १, ११; १९, १०; ३२, ११; ६२, ४; ८३, ७; ८. ४०, २; ६६, ५; १०. २९, १; २; ९३, ४; १२; ९९, ९; १११, १; १४८, ४.
नृऽतम ५. ४, ६; ६. ३३, ३; ७. १९, १०; ८. २४, १०.
नृऽतंमः १. ७७, ४; ३. १, १२; ४. ५, २; १६, ४; १७, ११; २२, २; ६. १८, ७; ७. ६, ४; १०. २९, १; ९९, ७.
नृऽतंमं ३. ३०, २२; ४९, २; ५१, ४; १०. ८९, १.
नृऽतंमस्य ३. १९, ३; ५. ३०, १२; १०. २९, २.
नृऽतंमाः ६. ४, ७.
नृतमानः ५. ३३, ६.
नृऽतंमाभिः ६. १९, १०.
नृऽतंमाय १. ५९, ४; ४. २५, ४; ८. २४, १.
नृऽतंमासः १. ८७, १; ६. २५, ७.
नृतयें १०. १८, ३.
नृतवः ८. २०, २२.
नृतुः ८. ६८, ७; ९२, ३.
नृतुः ५. ५२, १२.
नृतू इति ६. ६३, ५.
नृतूःऽइव १. ९२, ४.
नृतो इति १. १३०, ७[२]; २. २२, ४; ६. २९, ३; ८. २४, ९; १२.
नृतौ १०. २९, २.
नृत्यतांऽइव १०. ७२, ६.
नृऽधूतः ९. ७२, ४.
नृऽपतिः ४. २०, १; ७. ६९, १.
नृऽपतिं १. ७१, ८; ४. ३८, २; १०. ४४, ३; १०७, ५.
नृपती इति नृऽपती ७. ६७, १; ७१, ४.
नृपतीं इवेति नृपतींऽइव ७. १०४, ६; १०. १०६, ४.
नृऽपते १. १०२, ८; २. १, १; ७; ७. ३०, १; ८. ५४, ६; १०. ४४, २; ६१, २२.
नृऽपत्नीः १. २२, ११.
नृऽपाता १. १७४, १०.
नृऽपातारः ७. ७४, ६.
नृऽपानः १०. १०१, ८.
नृऽपानं १०. १०१, ७.
नृऽपाय्यं २. ४१, ७; ८. ९, १८; २६, १४; १५; १०. ३५, १२.
नृऽपीतये ७. १५, १४.
नृऽपीतौ ७. २०, ८.
नृऽपेशसः ३. ४, ५.
नृबाहुऽभ्यां ९. ७२, ५.
नृऽभिः १. ६४, १३; ६९, ३; ४; ७३, ९; ८१, १; १००, ६; १२९, २[२]; १३७, ३; १७८, ३; ४; २. २६, ३; ३. ३१, १५; ६०, ५; ४. १६, १९; १७, ११; ५४, १; ५. २५, ६; ८७, ४; ६. ३५, २; ४५, ६; ४८, ५; ७. १९, ४; २२, ७; २४, १; ३२, ६; ३६, ५; ४१, ३; ९२, ४; ९८, ४; ८. २, २; ३६; ४, १; १५, १२; २१, १२; ४०, ७; ४६, ८; ६२, २; ९. २४, ३; २७, ३; २८, १; ६२, ५; १६; ६८, ४; ७; ७५, ३; ५; ७६, १; ७८, २; ८०, ४; ८६, २०; २२; ३४; ८७, १; ९१, २; ९५, १; ९७, ५; ९९, ८; १०७, ५; १६; १०८, १५; १०९, ८; १५; १८; १०. ६८, १२; ६९, ७–९; ११; १०४, २; ११५, ७; १४७, ४.
नृऽभ्यंः १. ४३, २; ६; ६९, ४; ११०, ६; १२३, ३; १७३, ६; २. १९, ४; ४. १६, ४; ४१, ३; ६. १३, ५; १९, १२; २४, १; ७. २०, ५; २७, २; ४; ३८, २; ८. २, ३९; ६८, १३; ७७, ८; ९६, १; १०. ३९, १०; १४८, ४.
नृऽमनः १. ५१, ५; १०; ४. १६, ९; ७. १९, ४.
नृऽमनस्यसे ५. ३८, ४.
नृऽमनाः १. १६७, ५; ५. ५०, ४; ८. ९६, १३; १०. ४५, १; ३; ९२, १४.
नृऽमादनः ९. २४, ४; ६७, २.
नृऽमादनं १. ४, ७.
नृऽमेधः १०. १३२, ७.
नृऽमेधं १०. ८०, ३.
नृम्णं १. ८०, ३; १५; ५. १९, २; ३८, ४; ५४, १; ६. २५, ६; ४६, ७; ७. ४८, ३; ५६, ५; ८. ९, २; ९८, १०; १०. ४८, २; ५०, १.
नृम्णऽवर्धनः २. ३६, ५.
नृम्णस्यं १. ५५, ३; २. १२, १; १०. २२, ३.
नृम्णा १. ६७, २; ५. ५७, ६; ९. ७, ४; १५, ४; ६२, २३; ६९, ३; ७०, ३.
नृम्णानिं ४. २२, ९; ५. ३३, ६; ९. ४८, १; १०. १०२, ८.
नृम्णायं ७. ३०, १; ८. २, २९.
नृम्णैः ६. ६६, २.
नृऽवत् ३. ३४, ५; ४. २२, ४; ५५, ४; ५. १८, ५; ६. १, १२; १९, १; १०; ५३, १०; ७. २६, १; ८. ५, २; १८, २१; १०. २८, १२.
नृऽवतः १. ९२, ७; ६. १७, १४; २२, ३; ५०, ११.
नृऽवता ६. ६२, १०.
नृऽवति ६. २५, ६.
नृऽवतीः ७. ३, ८; १०. २, ६.
नृवत्ऽसखा ४. २, ५.
नृऽवंतः ७. ४१, ३.
नृऽवंतं ९. ९३, ५.
नृऽवाहनं २. ३७, ५.
नृऽवाहसा १. ६, २; ८. २५, २३.
नृऽशंसः ९. ८१, ५.
नृषु १. १८०, ८; ७. ३४, १८.
नृऽसत् ४. ४०, ५.
नृऽसदः १०. ३१, ११.
नृऽसदंनं ७. २०, १.

नृऽसदंने ५. ७, २; ७. ७, ५; ९७, १.
नृऽसदंनेषु ८. २६, २४; १०. ९२, ७.
नृऽसद्वां १०. ४६, १.
नृऽसहं ८. १६, १.
नृऽसह्यं ९. ३०, ३.
नृऽसह्याय १. ३३, १४; ८. ९, २०.
नृऽसह्ये १. १००, ५; ११२, २२; ६. २५, ८; ४६, ८; ८. ३६, ७; ९. ९७, १९; १०. ३८, १; ४.
नृऽसाः ९. २, १०.
नृऽसाचः १. ६४, ९.
नृऽसाचं: १. ५२, ९; ७. २१, २.
नृऽसाता ७. २७, १.
नृऽसूतः ८. ४, १.
नृऽहा ७. ५६, १७.
नृन् १. ७३, ९; १२१, १; १२; १३; १२२, १३; १४६, ४; १६९, ६; १७१, ६; १७४, १; १८१, ८; २. २०, १; ३. १४, ४; ४. २, १५; २१, २; ५. ७, १०; १५, २; ३३, १; ४१, ८; ५०, ३; ५४, १५; ५८, २; ८०, ६; ६. २, ११; ३, ६^{2}; ३५, २; ३९, ५; ५१, ४; ९; ७. १८, ७; २६, ५; २८, ३; ३३, १; ८. ३५, १७; ८४, ३; ९. ५६, ४; १०. १०, ६; २२, १०; २९, २; ४; ४६, ६; ४९, ११; ५०, ४.
नेतः ५. ५०, २.
नेतरिं २. ५, २.
नेतरितिं ५. ५०, ५.
नेता २. १२, ७; ३. ६, ५; १५, ४; २०, ४; २३, २; ४. १६, ८; ७. ५, २; ४०, ४; ८. ६९, १३; ९. ७४, ३; १०३, ४; १०. ८, ६; १०३, ८.
नेतारः १०. १२६, ६.
नेतारं १०. ४६, ४.
नेतुः ५. ५०, १.
नेत्री १. ९२, ७; ११३, ४; ७. ७६, ६; ७; ७७, २.
नेत्री इतिं ४. ५६, २.
नेथ १०. १२६, २.
नेदिष्ठः ४. १, ५.
नेदिष्ठऽतमाः ९. ९८, ५.
नेदिष्ठं १. १७, ३; १२७, ११; ५. ५६, २; ६. ५२, ६; ७. १५, १; ८. १, ४; ६०, १०; १८; ७३, ६.
नेदिष्ठाभिः ८. १९, २८.
नेदिष्ठे १. १३२, १.
नेदीयः ८. ५३, ५; ७५, ५; १०. १०१, ३.
नेदीयसः ८. २६, १०; १०. ८६, २०.
नेनिक्ते ९. ७१, ३.
नेमः ५. ६१, ८; ८. १००, ३; १०. २७, १८.
नेमऽधिता १. ७२, ४; ६. ३३, ४; ७. २७, १; १०. ९३, १३.
नेमन्ऽइषः १. ५६, २.
नेमे ९. ६८, ५; १०. ४८, १०.
नेमर्यः १. ३८, १२.
नेमस्मिन् १०. ४८, १०.
नेमानां ६. १६, १८.
नेमिः १. ३२, १५; १४१, ९; २. ५, ३; ५. १३, ६; ८. ३४, ३.
नेमिं ७. ३२, २०; ८. ४६, २३; ७५, ५; ९७, १२; १०. ६१, १६.
नेमे १. ५४, ८; ४. २४, ४; ५.
नेमे १. ५७, ५.
नेशत् ४. १, १७.
नेशत् ६. ५४, ७; १०. १२८, ६.
नेषणि १०. १२६, ३.
नेषत् १. १४१, १२; १०. १७, ५; १८२, १.
नेषऽतमैः १. १४१, १२.
नेषति ५. ४६, १.
नेषथ ५. ५४, ६; ८. ४७, ११.
नेषि १. १२९, ५; २. १, १६; २, १३; ३. १५, ३.
नेषि १. ३१, १८; ९१, १; ५. ४२, ४; ६. ४७, ८; ६१, १४; ८. १६, १२.
नेष्टरिति १. १५, ३.
नेष्टुः २. ५, ५.
नेष्ट्रं २. १, २.
नेष्ट्रात् १. १५, ९; २. ३७, ३; ४.
नैगुतः ९. ९७, ५३.
नैचाऽशाखं ३. ५३, १४.
नैतोशाऽइव १०. १०६, ६.
नैष्ट ८. ३०, ३.
नो इतिं १. १७०, १; १९१, १०–१२; ४. २१, ९; ६. ५४, ३; ८. ३३, १६; १०. ८६, २; १०८, १०; ११७, ६; १२९, १^{2}; १४५, ४.
नोर्धः १. ६४, १.
नोधाः १. ६१, १४; ६२, १३.
नोधाःऽइव १. १२४, ४.
नोनाव १. ७९, २.
नोनुमः १. ११, २; ७८, १–५; ४. ३२, ४; ७. ३१, ४; ३२, २२; ८. ६, ७; १२, २३; २१, ५; ६३, ११.
नोनुवंत ४. २२, ४.
नोनुवुः ६. ४५, २५.
नौ ७. ८८, ५; ८. ६२, ११; १०. १०, ४; ५^{2}; ८५, ४७^{2}; ८८, १७; ९५, १.
नौः ५. ५९, २.
नौभिः १. ११६, ३; ८. ८३, ३.
न्यक् ८. ४, १; २८, ३; ३२, २५; १०. ६०, ११^{3}; ९४, ५; १००, ८.
न्यङ् ४. १३, ५; १०. २७, १३; १४२, ५.
न्यंचं ५. ८३, ७.
न्यृष्टे इति निऽऋष्टे ३. ५५, २०.

प

पुक्तयै ४. २५, ७.
पुक्तिः ४. २४, ५; ६. २९, ४.
पुक्तिं ४. २५, ६.
पुक्तीः ४. २४, ७; ५. २९, ११; ७. ३२, ८.
पुक्थं ८. २२, १०.
पुक्थे ८. ४९, १०; १०. ६१, १.
पुक्तः १. ६६, २; ४. २०, ५; १०. ११६, ७.
पुक्तं १. ६२, ९; १६२, १२; १८०, ३; २. ४०, २; ३. ३०, १४; ४५, ४; ४. ३, ९; ६. १७, ६; ४४, २४; ७२, ४; ८. ३२, २५; ७७, ६; ८९, ७; ९. ९७,

५३; १०. ७९, ३; १०१, ३; १०६, ११.

पक्का १. ८, ८; ६. ६३, ९.

पक्काः ४. ४३, ५; ५. ७३, ८.

पक्के १०. ९४, ३.

पक्षः ६. ४७, १९.

पक्षः १०. ११९, ११.

पक्षत् १०. २७, १८.

पक्षत् ८. ६९, १५.

पक्षं १०. ११९, ७.

पक्षा १. १६३, १; ८. ४७, २; ३; १०. १०६, ३.

पक्षाऽइव ८. ३४, ९.

पक्षान् १. १६६, १०.

पक्षिणः १. ४८, ५; ८. २०, १०; १०. १२७, ५.

पक्षिणं १. १८२, ५.

पक्षिणीं १०. १६५, २; ३.

पक्षे १०. १२३, ५.

पक्षेभिः १०. १३४, ७.

पक्ष्या ३. ५३, १६.

पंक्तिऽराधसं १. ४०, ३.

पंक्तीः १०. ११७, ८.

पचत् ६. १७, ११.

पचंत ५. ३४, १; ७. ३२, ८.

पचतः ३. २८, २.

पचतं १. ६१, ७.

पचता १०. ११६, ८.

पचति १०. ८८, १०.

पचेत २. १२, १५.

पचत्यै ३. ५२, २.

पचन् ५. २९, ११.

पचनं १. १६२, ६.

पचंतं २. १२, १४; २०, ३.

पचंति १०. २८, ३; ८६, १४.

पचंतु १. १६२, १०.

पचात् ४. २४, ७.

पचाति ८. ३१, १; १०. २७, १८.

पचानि १०. २७, २.

पच्यंते १. १३५, ८.

पच्यते ६. २९, ४.

पच्यमानं ८. ६९, १४.

पच्यमानात् १. १६२, ११.

पज्रः १. १५८, ३; ८. ६३, १२.

पज्रऽहोषिणा ६. ५९, ४.

पज्राऽइव १०. १०६, ७.

पज्राः १. १२६, ४; ५; १९०, ५.

पज्रां १. १६७, ६.

पज्राय ८. ४, १७; ६, ४७.

पज्रायाः ९. ८२, ४.

पज्रासः १. ११७, १०.

पज्रियः १. १२०, ५.

पज्रियाय १. ११६, ७.

पज्रियेण १. ११७, ६.

पज्रे १. १२२, ७.

पज्रेभ्यः १. १२२, ८.

पज्रेषु १. ५१, १४.

पंच १. ७, ९; ८९, १०; १०५, १०; १२२, १३; १७६, ३; २. २, १०; १३, १०; ३४, १४; ३. ५९, ८; ४. ६, ८; ३०, १५; ३८, १०; ५. ३५, २; ८६, २; ६. ११, ४; ४६, ७; ५१, ११; ६१, १२; ७. १५, २; ६९, २; ७५, ४; ७९, १; ८. ९, २; ३२, २२; ७२, ७; ९. १४, २; ८६, २९; ९२, ३; ९८, ६; १०१, ९; १०. १३, ३; ४५, ६; ५३, ४; ५; ५५, २; ३; ६०, ४; ९३, १४; ११९, ६; १७८, ३.

पंचऽअरे १. १६४, १३.

पंचऽदश १०. ८६, १४.

पंचऽदशं १०. २७, २.

पंचऽदशानि १०. ११४, ८.

पंचऽपंच ३. ५५, १८.

पंचऽपादं १. १६४, १२.

पंचऽभिः ३. ७, ७; ५. ३४, ५.

पंचऽयामं १०. ५२, ४; १२४, १.

पंचऽरश्मिं २. ४०, ३.

पंचऽसु ३. ३७, ९; ९. ६५, २३.

पंचऽहोता ५. ४२, १.

पंचाशत् ४. १६, १३.

पंचाशतः १. १३३, ४.

पंचाशतं ५. १८, ५; ८. १९, ३६.

पंचाऽशता २. १८, ५.

पट्ऽगृभि १०. ४९, ५.

पट्ऽभिः ४. २, १२; १४; ३८, ३; ५. ६४, ७; १०. ७९, २; ९९, १२.

पठर्वा १. ११२, १७.

पड्बीशं १. १६२, १४; १६.

पड्बीशात् १०. ९७, १६.

पणयः १. १२४, १०; १५१, ९; ४. ५१, ३; ६. २०, ४; १०. १०८, ७; ८.

पणयः १०. १०८, २; ४; ६; १०; ११.

पणिः १. ३३, ३; १८०, ७; ५. ६१, ८.

पणिनां ४. २५, ७.

पणिनाऽइव १. ३२, ११.

पणिऽभिः ४. ५८, ४.

पणिऽभ्यः ९. २२, ७.

पणीं १. ९३, ४; ६. ४४, २२; ५१, १४; ६१, १; ८. ४५, १४; ७५, ७; १०. ६७, ६; १५६, ३.

पणीन् १. १८४, २; ६. ३३, २; ३९, २; ७. ६, ३; १९, ९; ८. २६, १०; ६४, २; ६६, १०; १०. ६०, ६.

पणीनां २. २४, ६; ६. ४५, ३१; ५३, ५; ७; ७. ९, २; ९. १११, २.

पणेः १. ८३, ४; १८२, ३; ३. ५८, २; ५. ३४, ७; ६. १३, ३; ५३, ३; ६; १०. ९२, ३.

पणौ ८. ९७, २.

पत ६. ७५, १६; १०. ९७, १३.

पतंगः १०. १७७, २.

पतंगं १. १६३, ६; १०. १७७, १.

पतंगरः ४. ४०, २.

पतंगाः १. ११८, ४; ५.

पतंगान् ४. ४, २.

पतंगाय १०. १८९, ३.

पतंगैः १. ११६, ४.

पतत् ३. ३९, ३.

पतत् ४. २७, ४.

पततः ६. ४, ५; ८. ७, ३५.

पतते ५. ७८, १.

पतंतां १. २५, ७.

पतति ६. ७५, ११; १०. १४, १६; १३६, ४.

पतत्रि १. १६३, ६; ३. ५४, ८; ४. २७, ४; १०. ८८, ४.

पतत्रिणः १. ४९, ३; ५८, ५; ९४, ११; १५५, ५.

पतत्रिणी इति १. १५८, ४.

पतत्रिणीः १०. ९७, ९.

पतत्रिऽभिः ६. ६२, ६; ७. ६९, ७; १०. १४३, ५.

पतत्रैः १०. ८१, ३.

पतथ १. १६८, ६.

पतथः ८. १०, ६.

पतथः १. १८३, १; ८. ३५, ७–९.

पतने ६. २०, ५.

पततः १०. ८०, ५.

पततं १०. ८७, ६; १२३, ६.

पतति १. २५, ४; ७९, २; ७. ८५, २; ८. ६९, १०; १०. ३८, १.

पतंति १. १६४, ४७; ४. ४, २.

पतंती १०. ९५, १०; १०८, ५.

पतंतीः ५. २९, ५.

पतंतु १०. १३४, ५.

पतंत्याः १०. १५८, २.

पतंयः ४. ४१, १०; ५०, ६; ५१, १०; ५७, २; ५. ४९, ४; ६. ४७, १२; ७. ४, ७; ८, ३; ३५, १२; ९. ८९, ७; ९५, ५.

पतयत् ६. ७१, ५; १०. ४०, ९.

पतयत् १. ४, ७.

पतयत् १. १५२, ५; ५. ४५, ९; १०. ४३, ८.

पतयतः ६. ९, ६.

पतयत्ऽभिः १. १५८, ३.

पतयत्ऽसु ६. ९, ५.

पतयंत १. १६९, ७.

पतयंतः १. २४, ६; १५५, ५; ४. ५४, ५.

पतयंतं १. १६३, ६; ९. ८६, ४३; १०. १६२, ३.

पतयंति १. १३५, ९; ५. ८३, ४; ६. ४६, ११; ७. १०४, १८; १०. ६४, २.

पतयंति ३. ५५, ३; ४. ५८, ७; ७. १०४, २०.

पतयिष्णवः ८. २७, १२.

पतयिष्णु १. १६३, ११.

पतरं २. २, ४.

पतराऽइव १०. १०६, ८.

पतरैः १०. ३७, ३.

पतरोःऽइव १. १८२, ७.

पतसि २. १६, ३.

पतात् १. ४६, ३.

पतात् १०. १६५, ५.

पताति १०. २९, ६; ४. १६, १७; ७. २५, १.

पतान् १०. २७, २२.

पतामि १. ३३, २.

पतिः १. १८, ४; ४०, ३; ५; ४४, ९; ५२, १३; ५३, २; ६६, ४; ६८, ४; १०१, ५; ११६, २५; १४५, १; १४९, १; १५३, ४; २. २३, १७; २४, २; ४; ५; ८; ९; ११; १३; २५, १–५; २६, ४; ३. ७, ३; ३१, ४; १८; ४. १६, ७; ५५, ४; ५; ५७, ३; ५. ४१, १२; ५१, १२; ६. ३६, ४; ४५, १६; ५८, ४; ७५, १७; ७. २६, ३; ३५, ५; १०; ८. १३, ८; ९; १९, ३७; ४४, १६; ७५, ४; ८०, ९; ९५, ३; ९८, ४–६; ९. ५, १; ११, ८; १५, ५; २८, १; ३१, २; ७२, ४; ७५, २; ८६, ५; ११; ३२; ३३; ९९, ६; १०१, ५–७; ११४, २; १०. १०, ३; २२, ३; २३, ३; २४, ३; २६, ६; ७; ४८, १; ५३, ९; ६५, १; ६७, ७; ७२, २; ७४, ६; ८५, २८; ३०; ३९; ४०; ८६, ११; ९९, ६; १०५, २; १११, ३; १२१, १; १२८, ७; १५२, २; १५९, २; १६२, ५; १७३, ३; १८०, १.

पतिःऽइव १०. १४९, ४.

पतिजुष्टाऽइव १. ७३, ३.

पतिऽस्वनं १०. ४०, ९.

पतिऽस्वं १. ११९, ५.

पतिऽद्विषः ८. ९१, ४.

पतिना ४. ५७, १.

पतिऽभ्यः १०. ४०, १०; ८५, ३८; ११०, ५.

पतिं १. ९, ४; ११, १; १८, ६; ३८, १३; ५६, २; ६०, ५; ६२, ११; ७१, १; ८९, ५; १०५, २; ११६, १०; ११७, ७; १२७, ८; २. ९, ५; २६, ३; ३. ३९, १; ४१, ५; ५. १२, ३; ३७, ३; ४१, ८; ४२, १४; ४६, ३; ६. १५, १; ४४, ४; ५; ७. ५, ५; ४१, १; ४४, १; ६६, १५; ९७, ३; ८. २४, १४; १८; २७, १; ६८, ४; ६९, २; ९. १४, ७; २६, ४; ६५, १; ८९, ३; ९७, २२; १०. १०, १०; ३२, ३; ४३, १; ४४, ४; ६१, ७; ६६, १३; ८१, ७; ८५, ७; १२; २९; ४५; ९२, १४; १०२, ७; १४५, १; २; १५९, १.

पतिऽरिपः ४. ५, ५.

पतिऽलोकं १०. ८५, ४३.

पतिऽवती १०. ८५, २१.

पतिऽविद्यं १०. १०२, ११.

पतिष्ठः १०. १६५, ५.

पती इति १. २३, ३; ५; ११९, ५; १३६, ३; २. ३१, ४; ४१, ६; ४. ४३, ६; ५. ६३, ३; ६८, ५; ८६, ४; ८. ५, ५; २२, १४; २६, ६; १०. ४०, १४; ९३, ६.

पती इति १. ३, १; ३४, ६; ४७, ५; १२०, ६; ४. ४७, ३; ५. ७५, ८; ८. ५, ११; ८, १६; २२, ४; ६; ५९, ३; ५; ८७, ५; १०. ४०, ४; १२; १३; ८५, १५; १३१, ४.

पते १. ११, २; १८, १; ३; ५; २६, १; २९, २; ३०, ५; ४०, १; १३१, ४; २. १, ३; २३, १; ५; ९; ११; १९; २४, १५; १६; ३. ५१, १०; ४. ५७, २; ५. ६, ५; ९; ३५, ५; ६. ४५, १०; ५३, १: ७. ५४, १–३; ५५, १; ९७, ९; ८. ६, २१; १७, १४; १९, ७; २३, १२; ४५, २०; ६०, ९; ९०, ५; ९२, ३०; ९३, ३१; ९७, ६; ९. ३१, ६; ३६, ६; ८३, १;

१०४, ५; १०५, ५; १०८, ९; ११३, २; १०. १४१, १; १५५, २; १६४, १; ४; १६६, ३; १७४, १.
पतेः २. २४, १४; २६, २; ९. ३५, ६.
पत्तः १०. २७, १३.
पत्तवे ४. १८, १.
पत्नीं ३. ६१, ४; ४. २४, ८; ७. ७५, ४.
पत्नीऽइव १. १२२, २.
पत्नीः १. २२, ९; ६२, १०; ११; १०३, ७; ११२, १९; १४०, ६; १७९, १; २; १८६, ७; ४. ५, १३; ५. ४१, ६; ४२, १२; ४४, ५; ४६, ७; ५०, ३; ७. ३४, २०; १०. ३०, १०; १२.
पत्नीभिः २. १६, ८.
पत्नीं १०. ८५, ३९.
पत्नीऽवतः १. १४, ७; ३. ६, ९.
पत्नीवत्ऽभिः ४. ५६, ४.
पत्नीऽवंतः १. ७२, ५; ८. २८, २; ९३, २२.
पत्न्यां १. ८२, ६; १०. ३९, ११.
पत्ऽभ्यां १०. ९०, १२; १४.
पत्मं १०. ५६, ३.
पत्मन् १. १४१, ७; ५. ५, ७; ४१, ३; ६. ४, ६; ७. ३४, ५; १०. ८, ३.
पत्मना ६. ३, ७.
पत्मऽभिः ८. ८, २३.
पत्यंते २. ३७, २; ६. १३, ४; २२, १; ४५, २०; १०. १४४, १.
पत्यते १. ८४, ९; १२८, ७; ३. ३६, ४; ५४, ८; ५६, ३; ६. २५, ६; ८. १, २६; १०२, ९; ९. ४५, ४; १०. २३, २.
पत्यमानः ३. ५४, ११; १५; ६. ४९, ४; ७. १८, ८; १६.
पत्यमानं ६. ६६, १.
पत्यमानाः ३. ५६, ५; ६. २७, ६; ६५, ३; १०. १३२, ३.
पत्यमानान् १०. २७, ६.
पत्यसे ६. २, १.
पत्यसे २. १, ८.
पत्यां १०. ८५, २२; २४; २७; ३६.
पत्युः १०. १८, ८.
पत्यै १. ६१, २; १२४, ७; १०. १०, ७; ८५, ९; २०.
पत्यौ ९. ८२, ४; १०. १५९, ३.
पत्ऽवत् १. ४८, ५; ३. ३९, ६.
पत्ऽवती १०. ८५, २९.
पत्ऽवतीनां १. १५२, ३.
पत्ऽवतीभ्यः ६. ५९, ६.
पत्ऽवती १. १४०, १२.
पत्ऽवते १. १४०, ९; १०. १६९, १.
पत्ऽवंतः १०. १२७, ५.
पत्ऽवंतं १. १८५, २.
पत्वऽभिः ५. ६, ७.
पत्वा ९. ९६, २३.
पत्ऽसु ५. ५४, ११.
पत्सुतः ८. ४३, ६.
पत्सुतःऽशीः १. ३२, ८.
पथः १. ४२, २; ८३, ५; ९०, ४; १०५, ११; २. १३, ५; २३, ७; २४, ७; ३०, २; ३. ३०, १०; ४. ३७, ७; ४५, ३; ६; ५. ४६, १; ८०, २; ३; ६. १६, ३; ५३, ४; ७. ४, ७; १८, १६; ३९, ३; ८७, १; ८. ५, ९; २९, ६; ३०, ३; ५५, ५; ९. ९, ८; २२, ४; ९१, ५; १०१, ८; १०. ५१, ५; ५३, ६; ५७, १; ७३, ७; ७५, २; ९८, ११; ११०, २.
पथुः ६. ५३, १.
पथःऽपथः ६. ४९, ८.
पथा १. ३८, ५; ४१, ५; ८७, २; १०५, ६; १८; १२८, २; १२९, ९; २. ४, ६; ४. २६, ५; ५. ४५, ८; ४७, ६; ६४, ३; ७. ६५, ३; ८. ५, ३९; ९. ७, १; १५, ३; ८६, १६; १०. १४, १०; २२, ४; ३१, २; ५०, ७; ५२, १; ७०, २; ८६, २१; ९३, १४; ११४, ७; १३३, ६; १४५, ६.
पथाऽइव १. १३९, ४.
पथां ४. ४०, ४; ७. ७३, ३; १०. ५, ६; १७, ६.
पथि ३. ५४, ९; ६. ४४, ८; ४६, १३.
पथिऽकृत् २. २३, ६; ६. २१, १२; ९. १०६, ५; १०. १११, ३.
पथिकृत्ऽभ्यः १०. १४, १५.
पथिऽभिः १. ३५, ११; ५८, १; ७९, ३; १६२, २१; १६३, ६; १६४, ३१; १८३, ६; १८४, ६; २. १५, ३; ३४, ५; ४. ३७, १; ५. ४३, ६; ६. ४, ८; १८, ११; ६९, १; ७. ३८, ८; ६४, ३; ८. २२, ७; १०१, १०; ९. ८६, ३३; ९१, ३; ९७, २८; १०६, ६; १०. १४, ७; ८७, ६; १६८, ३.
पथिरक्षी इति पथिऽरक्षी १०. १४, ११.
पथिषु ५. ७, ५.
पथीनां ५. १, ११.
पथेऽस्थां ५. ५०, ३; १०. ४०, १३.
पथ्यां ३. ५४, ५; ५५, १५; ७. १८, ३; ७९, १.
पथ्याऽइव १०. १३, १.
पथ्याः ३. १२, ७; ३५, ८; ५. ५४, ९; ६. १९, ५; ६६, ७; ७. ७, २; ७५, १; १०. १४, २.
पथ्याभिः ३. १४, ३; ७. ६७, ३; ९. ८९, १.
पथ्यां ३. ३१, ५; ७. ४४, ५; ९. ९५, २; १०. ५९, ७; ८०, ६.
पथ्यासु १०. ६३, १५.
पथ्ये ५. ५१, १४.
पदः १. १४६, २.
पदऽज्ञाः १. ६२, २; ३. ५५, २; ९. ९७, ३९.
पदं १. २२, ५; १७; २०; २१; २५, ७; ४८, ६; १०५, १; १४६, ४; १५४, ६; १५९, ३; १६४, ७; २३; ३. ५, ५; ६; ७, ७; ४. ५, ३; ५; ८; १२; ५. ३, ३; १५, ५; ३०, २; ६. १, ४; ८. १३, २९; ४१, ४; ७२, १८; १०२, १४; १५; ९. १०, ७; ९; २३, २; ६४, १९; ६८, ४; ७१, ५; ८३, ४; ८६, १५; १०२, २; १०. ५, १; २; १८, २; ३२, ५; ६७, २; १०८, ७; १६५, ३; ४; १७७, १.

पदऽवीः ३. ५, १; ३१, ८; ५६, ४; ७. ३६, २; ९. ९६, ६; १८.
पदऽवीयं १०. ७१, ३.
पदऽव्यः १. ७२, २.
पदस्यं ७. ८७, ४.
पदा १. २२, १८; ४२, ४; ५१, ६; ७२, ६; ८४, ८; १३३, २²; १६४, ७; १७; ६. ५९, ६; ८. १२, २७; ४१, ८; ५२, ३; ६४, २; ८२, ९; ९. १२, ८; ९७, ७; १०. ५३, १०; ६१, ८; १३४, ६; १४४, ५.
पदाऽइंव ४. ३१, ५; ५. ६७, ३; ८. १२, ३१.
पदाति ९. ७३, ९.
पदानि १. ६७, ३; १५४, ४; १६४, ५; ४५; ८. ८, २३; १०. ८, ४; १३, ३.
पदायं ७. ४१, ६.
पदि ४. १२, ६.
पदि १. १२५, २.
पदीष्ट १. ३८, ६; ७९, ११.
पदीष्ट ३. ५३, २१; ७. १०४, १६; १७.
पदे १. २१, ६; २२, १४; ४६, ९; ७२, २; ४; १२८, १²; १४९, १; १५४, ५; १५८, २; १६३, ७; २. १०, १; २३, १६; ३५, १४; ३. २३, ४; २९, ४; ५४, ७; ५५, १; ४. ५, ९; १०; ५. ७४, ४; ६. १, २; ८. २३, ९; ५१, ४; ६९, ७; ९. ८३, २; ९७, ५७; १०. १, ६; ७०, १; ९१, १; ४; १७७, २; १९१, १.
पदे इवेति पदेऽइंव ३. ५५, १५.
पदेन १. १३९, ९.
पदेऽपंदे ५. ४१, १५; ९. ७३, ४.
पदेभिः १. १५४, ३.
पदेभ्यः ८. २, ३९.
पदैः १. ६५, १; १०. ४६, २.
पदोः १०. १६६, २.
पद्यते ४. १३, ५; ६. ५४, ३; १०. १४६, ५.
पद्यस्य ६. ७५, १६.
पथ्या ३. ५५, १४.

पथ्याभिः २. ३१, २; ३२, ३; १०. १०२, ७.
पथ्यासु ७. ६, १६.
पथ्येन ७. ५०, १.
पनंत २. ४, ५.
पनंत १०. ७४, ४; १०४, ७.
पनय ५. २०, १.
पनयत् ४. ३३, ५.
पनयंत ३. ६, ७; ७. १, १०.
पनयंत १. ८७, ३.
पनयंति ६. ४, ३.
पनयंति ३. ३४, ६; ४. ३८, ९; ६. १२, ५.
पनयाय्यं ६. ६९, ५.
पनस्यते १०. ७५, ९.
पनस्यते १. ५५, २; ३. ५१, ३; ८. १०१, ११.
पनस्यवः १०. ७७, ३.
पनस्यवे ८. ९८, १.
पनस्युं १. ३८, १५; ५. ५६, ९.
पनस्युवः ९. ८६, १७.
पनायत ६. ७५, ६.
पनाय्यं १. १६०, ५; ८. ५७, ३.
पनितः ५. ४१, ९.
पनितारः ३. ५४, ९; ५७, १.
पनितारं ५. ४१, ६.
पनिप्नतं ९. ६७, २९; ८५, ११; ८६, ३१; ४६.
पनिष्ट ७. ४५, २.
पनिष्टः ६. ५९, २.
पनिष्टं ३. १, १३.
पनीयसी १. ३९, २; ५. ६, ४; १०. ६४, १५; ९२, ४.
पनीयसे १. ५७, ३.
पंथाः १. ३५, ११; ४१, ४; ४६, ११; १०५, १६; १३६, २; १९०, ६; २. २७, ६; ३. ५४, २१; ४. १८, १; ५. ४७, २; ७. ७६, २; ८. १८, २; ३१, १३; १०. ८५, ११; २३; १०७, १; १०८, ६.
पंथां १. २४, ८; ९१, १; ११३, १६; १२४, ३; १२७, ६²; ४. ३५, ३; ५५, ४; ५. १०, १; ५१, १५; ६. १७, १२; ४७, २०; ५१, १६; ७. ३९, १; ४४, ५; ७१, १; ८. ७, ८; १२, ३; ६८, १३; ९. ७३, ६; ९७, ३२; १०. २, ३; ७; १४, १; १८, १; ६६, १३; ७१, ६; १७७, ५; १३०, ७; १४२, ७.
पंथासः १. १००, ३.
पन्यः ३. ३६, ३; ८. ३२, १८.
पन्यऽतमाय ३. ५९, ५.
पन्यंऽपन्यं ८. २, २५; ७४, १०.
पन्यंसा ६. १८, ९; १०. २७, १२.
पन्यंसीं ६. ३८, १.
पन्यंसे ९. ९, २.
पन्यांसं ८. ७४, ३.
पन्ये ८. ३२, १७³.
पन्वा १. ६५, २.
पपथुः १. ४७, १०.
पपन ८. २, १७.
पपाथ ७. ९८, ३.
पपाद १०. ३४, ११; ११४, ९.
पपानः ६. ४४, ७.
पपिः ६. २३, ४.
पपिरे २. २४, ४.
पपिऽवांसं ३. ४३, ५; ५. २९, २; ६. ४७, १.
पपिऽवांसः १. १०८, १३.
पपिऽवान् १. ६१, ७; २. ११, १०; ३. ५०, ३; ५. २९, ३; ३०, ११; १०. ८५, ३; ९४, ९; ११२, ५.
पपीयात् ६. ३७, २; १०. २८, १.
पपुः ९. १०६, ८.
पपुरि ६. ४६, ५.
पपुरिः १. ४६, ४.
पपुरिं १. १२५, ४; ४. २३, ३.
पपुर्वः १०. ४४, २.
पपृक्षे ४. ४३, ७.
पपृक्षेण्यं ५. ३३, ६.
पपृचानस्यं ९. ७४, ९.
पपृचानासः १. १४१, ६.
पपृचासि १. १४१, ११.
पपृच्यात् ४. २४, ५.
पपृच्यां १०. १०, १२.
पपे ८. ३२, १६.

पपौ १. १६२, १४.
पप्तः १०. ९५, १५.
पप्तत १. ८८, १.
पप्तन् २. ३१, १.
पप्तन् ६. ६३, ६.
पप्तिम ९. १०७, २०.
पप्तिऽवांसः १. ४८, ६.
पप्तुः ५. ५९, ७.
पप्तुः २. २८, ४.
पप्ते ६. ६०, ४.
पप्रतुः ८. ४१, ९.
पप्रथः ३. ३०, २०.
पप्रथत् १. १०३, २; २. १५, २; ७. ८६, १.
पप्रथत् २. २५, २; ७. ४२, ६; ८. ३, ६.
पप्रथन् २. ११, ८.
पप्रथन् ८. ९४, ९.
पप्रथन्त १०. ८८, १.
पप्रथानः ५. १५, ४; ७. ६९, २.
पप्रथाना ७. १८, ५; १०. ३१, ६.
पप्रथानाः ३. ५४, १०; ४. ५१, ८.
पप्राथानेभिः ४. ५६, १.
पप्रथुः ६. ७२, ३.
पप्रथे ५. ३८, २; ६. ७, ७.
पप्रथे १. ५५, १; २. २४, ११; ३. ३०, १९; ६१, ४; ५. ८७, ७; ८. ३, ४; १२, १२; ५१, १०; ८६, ५; ९. ८०, ३; १०. ६२, ९; ६९, २; १७०, ३.
पप्रा १. ६९, १.
पप्राथ ६. १७, ७.
पप्राथ ७. २०, ४; ९८, ३; ८. ६८, २; ७०, ६.
पप्रिः १. ५२, ३; ६. ५०, १३; ८. १६, ११.
पप्रिणा २. २३, १०.
पप्रिं १. ९१, २१.
पप्रिषे १०. ७३, ८.
पप्रुः १०. ६५, २; ६६, ९.
पप्रौ ६. १०, ४; ४८, ६; १०. ८९, १.
पप्रौ १. ८१, ५; ३. ३०, ११; ५४, १५; ४. १६, ५; ८. २५, १८.
पयः १. २२, १४; २३, १६; ६२, ९; ६४, ६; ६६, १; १०४, ४; १०५, २; १२१, ५²; १६०, ३; १६४, २७; १८०, ३; २. १३, १; २; ३. ३१, १०; ४. ५७, २; ५; ५. ४४, १३; ८५, २; ६. ४८, २२; ५२, १०; ६७, ७; ७. ७४, ३; ९५, २; १०१, ३; ८. ९३, १३; ९. ६, ७; ११, २; १९, ५; ३१, ५; ३४, ३; ४२, ४; ५४, १; ६२, ९; २०; ६६, ३०; ७१, १; ७४, ४; ८६, ३७; ९१, ३; ९६, १५; ९७, ४३; ११०, ३; १०. १, ३; १७, १४; ६३, ३; ६४, ९; ६५, ६; ८; ७३, ९; ८७, १७; ११४, १.
पयःऽधाः ७. ५६, १६.
पयःऽपाः १. १८१, २.
पयःऽभिः १. १६४, २८; ४. २१, ८; ५७, ८; ७. ६८, ९; ९. ६२, ५.
पयःऽवृधः १. ६४, ११.
पयःऽवृधं ९. ८४, ५; १०८, ८.
पयःऽवृधा ८. २, ४२; ९. ७४, १.
पयंते १. १६४, २८.
पयसः १. १५३, ४; १०. ६१, २६; १००, २.
पयसा १. ६४, ५; ७९, ३; १६६, ३; २. १४, १०; ३. ३३, १; ४; ५५, १३; ४. ३, ९; १०; ४१, ५; ५. ४३, १; ६३, ५; ६. ६१, १४; ७. ३६, ६; ५०, ४; ९. ६८, ३; ८४, ५; ८६, २; ४; १७; ९३, ३; ९७, १४; ४३; १०७, १२; १०. १९, ७; १३२, ६.
पयसाऽइव ९. ७७, १; १०. ६४, १२; ७५, ४.
पयसि १. १८६, ४.
पयस्वत् १०. १७, १४².
पयस्वती ४. ५७, ७.
पयस्वती इति २. ३, ६; ६. ७०, २.
पयस्वतीः १०. १७, १४.
पयस्वान् १. २३, २३.
पयांसि १. ९१, १८; ८. १००, १०; १०. ११, १; ३०, १३; १०८, १; २.
परः १. १६४, ३५; २. ४१, ८; ६. ६३, २; १०. ८८, १७.
परः १. ८, ५; १९, २; ८०, १५; १६४, १७; १८; ४३; २. १३, १०; २३, १६; ३५, ६; ५. ३, ५; १७, २; ३०, ५; ४४, २; ६. ९, २; ३; ७. ९९, १; १०४, ११; ८. २, ४१; ६, ३०; ८, २३; २२, १४; २७, १८; २८, १; ६९, १४; ७२, ३; ९. ६८, ५; १०७, २०; १०. १७, १३; २७, २१; ३१, ८; ५६, १; ६७, ४; ७१, ९; ८२, २; ५³; १२९, १; २; १६४, १².
परःऽगव्यूति ८. ६०, २०.
परःऽतरं १०. १५५, ३.
परःऽपा ८. ९, ११.
परःऽपाः २. ९, २; ६; ५. ६२, ६; ८. ६१, १५.
परःऽमात्रं ८. ६८, ६.
परऽस्तरे १०. ९५, १.
परं १. ३३, १; १४०, ८; १५५, ३; १६४, ३४; १६८, ६; ७. ९९, २; ७. ९९, २; १०. १८, १; ८७, ३; १२०, ७.
परमः ५. ३०, ५; ६. २७, ४; ९. ७९, ४.
परमऽज्याः ८. १, ३०; ९०, १.
परमं १. २२, २०; २१; ३१, १४; १०३, १; १५४, ६; १६३, ४; १३; १६४, ३४; ३५; २. २४, ६; ३. ५५, १०; ४. ५, १२; ८. १००, १०; १०. १, ३; १०, ४; ४५, २; १८१, २.
परमया ६. ३८, ३.
परमस्य ४. १२, ३; ७. ३२, १६; ६०, ११; ९९, १.
परमस्याः ५. ६१, १.
परमस्याः १. १०८, ९; १०.
परमा २. २७, ३; ३. ३०, २; ४. १, ७; ५०, ३; ६. २५, १; १०. ६१, १८; ८२, २.
परमाः १. १६७, २; ५. ४७, ४.
परमाणि ४. १, १६; १०. ८१, ५.

परमात् १. १४१, ४; ८. ११, ७; ९. ८७, ८.
परमाभिः ६. ६२, ११.
परमां १०. ९५, १४.
परमे १. ६२, ७; ७२, २; ४; १०१, ८; १४३, २; १५४, ५; १६४, ३९; ४१; २. ९, ३; ३५, १४; ३. ३२, १०; ४. ५, १०; ५०, ४; ५. १५, २; ४५, ८; ६३, १; ७. ५, ७; ८२, २; ९. ८६, १५; १०. ५, ७; १४, ८; १६, १०; ५६, १; १०९, ४; १२३, ५; १२९, ७.
परमे इति ४. २३, १०.
परमेषुं १. २७, ५.
परशुः १. १२७, ३; ६. ३, ४; ७. १०४, २१; ९. ६७, ३०; १०. ४३, ९.
परशुं ३. ५३, २२; ४. ६, ८; १०. ५३, ९.
परशुमान्ऽइव ८. ७३, १७.
परशून् १०. २८, ८.
परशोःऽइव ५. ४८, ४.
परश्वाऽइव १. १३०, ४.
परस्तात् ३. २२, ३; ५५, ६; ६. ५४, १०; १०. ८८, १४; १२९, ५.
परंस्मात् ७. ६, ७.
परंस्मिन् १. ४३, ९.
परंस्य ३. १८, २; ६. १५, ३; १०. ८, ७.
परंस्याः ८. ७५, १५; १०. ५५, ४; १८०, २; १८७, २.
परंस्वंतं १०. ८६, १८.
परा १. ४, ४; २५, ४; १६; ३३, ५; ३९, ३; १०४, ५; ८; ११६, ९; १२३, १२; १२६, ७; १६४, १७; ३१; १६७, ४; १८९, ५; २. २८, ९; ३. ५३, २; ५; ४. १६, ७; ३८, ९; ५. ३, १२; ६१, ४; १७; ८२, ४; ५; ६. २०, ११; २६, ३; २७, ७; ४७, १७; ५९, ७; ६९, ८[2]; ७५, १६; ७. १, १९; १८, १६; ३२, २५; ४६, ४; १०४, १; ८. १, ५; २, १५; ४, १८; ४७, १४; ४८, ८; ७१, ७; ७५, १२; ९७, ७; ९. ७१, ७; ८१, ३; १०. ८, ९; १७, ६; १८, १; ३०, ५; ४८, ५; ५९, ४; ६१, ८; २१; २३; ७२, ८; ८५, २९; ३३; ८६, २; ८७, १४[2]; १५; १८[2]; ९५, २; १३; ९९, ९; १०३, १२; १२८, ८; १३७, २; ४; १४५, २; १६०, ३.
पराऽअयंनं १०. १९, ४; ५; २४, ६.
पराऽअयंने १०. १४२, ८.
पराऽआर्स ४. १८, ८.
पराऽहृतः १०. ८३, ५; १६१, २.
पराऽहृतौ १०. १७८, २.
पराऽईयुः १०. १४, २.
पराः १०. ५८, ११.
पराकात् १. ३०, २१; ७. ७५, ४; ८. ५, ३१; १०. २२, ६; ७७, ६; १०८, ३; ४.
पराकात्तात् ८. ९२, २७.
पराके १. १२९, ९; ७. १००, ५; ८. ९, १५.
पराऽगताः १०. ९७, २१.
पराचः १. १६४, १९; ३. ३०, ६; ६. २५, ३; ४४, १७; ७. ८५, २.
पराचीः १. १९१, १५.
पराचैः १. २४, ९; ६३, ४; १०३, १; ६. ७४, २; १०. ५५, १;१०८,१.
पराऽजितासः १०. ८४, ७.
पराचः १. १६४, १९.
पराणि ३. ३८, १; ६. २१, ६; १०. ५, २.
पराऽतरं १०. ५९, १.
पराऽददः ८. ७०, १४.
पराऽददाति १. ८१, ६.
पराऽदुदिः १. ८१, २.
पराऽदै ७. १९, ७.
पराऽनुदे १. ३९, २; ८. १४, ९.
पराऽपरा १. ३८, ६.
पराऽभृतं ८. ४५, ४१.
परा १०. १४५, ४.
पराऽयतिः ९. ७१, ७.
पराऽयती १. १९१, २.
पराऽयतीनां १. ११३, ८.
पराऽयतीं ४. १८, ३.
परायत्ऽभ्यः १०. ३४, ५.
पराऽयन् १०. ४५, ६.
पराऽधत् ४. ५०, ३.
पराऽवतः १. ३४, ७; ३५, ३; ३६, १८; ३९, १; ४८, ७; ७३, ६; ९२, ३; १२८, २[2]; १३०, १; ९; ३. ९, ५; ३७, ११; ४०, ८; ४. २१, ३; २६, ६; ३०, ११; ५. ५३, ८; ६१, १; ६. ८, ४; ४४, १५; ४५, १; ७. ९७, २; ८. ३, १७; ५, ८; ३०; ६, ३६; ७, २६; १२, ६; ३०, ३; ३२, २२; ८२, १; ९. ३९, ५; ६८, ६; १११, २; १०. ५८, ११; ६३, १; ७८, ७; १३७, २; १४४, ४; १८०, २; १८७, २.
पराऽवतं ३. ४०. ९; १०. ९५, १४; १४५, ४.
पराऽवति १. ४७, ७; ५३, ७; ११२, १३; ११९, ८; १३४, ४; ५. ३०, ५; ७३, १; ८. १२, १७; १३, १५; ३३, १०; ४५, २५; ५०, ७; ५३, ३; ९३, ६; ९. ४४, २.
पराऽवृक् २. १५, ७; १०. ६१, ८.
पराऽवृक्तं ४. ३०, १६.
पराऽवृजं १. ११२, ८; २. १३, १२.
पराऽशुरः ७. १८, २१; १०४, २१.
परासः ४. २, १६; १०. १५, १.
पराऽहता ५. ५६, ३.
परिं १. ६, १; ७, १०; १०, १२; १५, ४; २३, १२; २५, १३; ३०, १९; ३१, २; ४; ५; १५; ३३, ८; ९; ३४, ७; ४७, ६; ४९, ३; ५०, १०; ५२, ६; ५४, ५; ६१, ८[2]; ९; ११; ६२, ८; ६८, १; ६९, १; ७२, २; ७६, १; ८०, ९; ८८, ४; ९३, ६; ९५, २; ३; ८; ९; १०५, ३; १०८, ७–१२; ११२, २५; ११५, ३; ११८, ५; १२१, २; ७; १०; १२३, ८; १२४, ६; १२७, ९; १२८, ३; १३२, ६; १३३, १; १३५, २; १३६, ५; १४०, ९; १४१, ४; १४३, ८; १४६, ४; ५; १५२, ४; १६२, १;

४; १३; १६४, ११; २०; २५; ३६; १६७, ९; १६८, ९; १७२, ३; १७३, ३; १७८, १; १८०, १; १०; १८३, ४; **२.** १, १; २, ५; ५, ३; ६, ५; १३, १; २; १०; १७, ६; २३, १७; २७, ५; ३०, ९; ३१, १; ३३, १४^{२}; ३५, ३; ४; ९; १०; १२; १४; ४१, १२; **३.** १, ५; २, ६; ७; १२; ३, २; ९; ५, १०; ७, २; ६; ९, ३; ५; ११, ८; १२, ७; ९; १५, ६; २६, ८; २९, ६; ३१, १७; ३२, ६; १६; ३६, ९; ३८, ४; ६; ९; ४८, २; ५१, ८; ५३, ८; २४; ५६, ४; ५८, ८^{२}; **४.** १, १५; २, ९; ३, ११; ६, ४; ५; ९, ३; ८; १५, १–३; ३०, १२; ३१, ८; ३३, १; ३६, १; २; ८; ३८, ४; ४०, ३; ४१, ७; ४३, ५; ६; ४५, ७; ४९, २; ५२, १; ५६, ७; **५.** १५, ३; ४; १६, ४; १८, ४; २९, १३; ३१, ७; ३७, ३; ४१, १२; ४४, ७; ४७, २; ४; ५१, ४; ५३, ९; ५५, ७; ५९, ७; ६४, १; ६५, ६; ७३, ३; ५; ७५, ७; ७९, ५; ८१, ४; ८३, ७; **६.** ४, ६; ७, ७; १६, ३२; १७, ५^{२}; २८, ७; ३९, २; ४७, २७^{२}; ४८, २१; ५१, १६; ५३, ५; ५४, १०; ६२, १; ३; ६३, २; ६७, ५; ७०, ३; ७१, ३; ७५, १२; १४^{२}; **७.** १, ११; १५; १६; ३, ७; ४, ६; ५, ७; १८, २२; २०, ७; ३१, ८; ३२, १०; ३३, १; १०; १२; ३४, २३; ३६, ७; ४६, ३^{२}; ५०, २; ३; ६०, ९; ६७, ८; ६९, ४; ७५, ४; ७६, ३; ८४, १; २; ८७, ३; ९३, ८; १०३, ७; १०४, ५; ६; **८.** १, २७; ६, १०; २०; ८, ३; ४; ८; २३; ९, ४; २२, ४; ५; २५, १८; २६, १४; ३३, १; ३४, १०; ३९, १०; ४१, ३; ७; ४५, १०; ४७, ५; १५; ६६, ९; ६७, ८; ६८, ३; ६९, ९^{२}; ७२, ९; १८; ७६, १२; ८०, ६; ८८, ५; ९१, ३; ९२, १९; १०१, १६; **९.** ७, ४; ६; ८, ६; ८; ९, १; १०, ४; ११, ८; १२, ५; १४, १; ८; १७, ४; १८, १; ६; २०, ३; २७, २; ३९, १; २; ४; ४१, ६; ४२, २; ४; ४९, १; ५०, ३; ५२, १; २; ५४, ४; ५५, १; ५६, १; ४; ६१, १; ३; १२; ६२, ९; १३; २३; ६३, १०; १९; २७; ६४, ८; १८; २३; ६५, २; २४; ६६, ३; ६७, १५; ६९, २–६; ७०, २; ७१, ४; ९; ७२, ८; ७३, ३; ५; ७५, ५; ७६, ५; ७७, २; ७८, २; ८०, १; ८२, १; २^{२}; ८३, १; ५; ८४, २; ८५, १; ८६, १; ५; ६; ७; २०; २४–२७; ३२; ३३; ४६; ४८; ८७, १; ४; ६; ७; ९; ८९, ३; ५; ९२, १; ६; ९३, १; ९४, ३; ९६, ९; २०; २१; ९७, १; १०; १५^{१}; १९^{२}; २१; ४८; ९८, २; ७^{२}; १०; १००, ४; १०२, १; १०३, २–६; १०४, १; १०५, ६; १०६, १४; १०७, १–३; ६; १८; १०८, ७; १०९, १; ११०, १^{२}; **१०.** १, २; १०, २; १३; ११, २; १२, ७; १४, ११; १६, २; ७; १७, ३; ४; १२; १८, १३; १९, ७; २२, १४; २७, ७; ३०, ९; ३१, २; ३२, ५; ३४, ४; ३७, २; ८; ३८, ५; ३९, ४; ४०, ५; ६^{२}; ७; ४२, ११; ४३, १; ६; ४५, १^{२}; ४८, २; ४९, ७; ५६, ५; ६२, ५; ६^{२}; ६३, २; ८; ६६, ३; ६८, ८; ७२, ३; ४; ८; ७५, ७; ८०, ५; ८५, १३; १८; ३८; ८७, ३; १०; २१; २२; ८९, २; ९१, ५; ९४, ८; ९७, १७; ९९, ३; १००, १२; १०१, १०; १०३, ४; १०८, ५; ११४, १०; ११५, ४; ११६, ९; ११९, ५; १२६, ४; १२८, ६; १३३, २; १३५, ४; १३९, ४; ६; १४२, ३; १५१, ५; १५५, ५^{२}; १६५, २; ५; १६७, १; २; १७९, २.

परिऽअक्षरत् **९.** ६४, ११.

परिऽअंखयाते **१०.** १६, ७.

परिऽअतिष्ठत् **१.** ३२, ८.

परिऽअपश्यत् **१०.** ५१, २; १२१, ८.

परिऽअभूवन् **१.** ३३, १०.

परिऽअभूषत् **२.** १२, १.

परिऽअयाः **९.** ८२, ५.

परिऽअसर्पत **१.** १६१, १२.

परिऽअसस्वजत् **१.** १८२, ७.

परिऽआवर्त **१०.** १२४, ४.

परिऽआविवृत्सन् **७.** ६३, २.

परिऽईयसे **८.** ४९, ८; ५०, ८.

परिऽउह्यमाना **१०.** १७, १.

परिंऽएतवे **८.** २४, २१.

परिऽएता **१.** २७, ८; **६.** २४, ५; **७.** ४०, ३.

परिऽएति **९.** ७४, २; **१०.** ६, १; ६५, ६.

परिंशं **१.** १८७, ८.

परिऽकृण्वन् **९.** ३९, २.

परिऽकृण्वंति **९.** १४, २.

परिंऽकृतः **३.** २८, २; **८.** ३९, ९; **९.** ४३, ३; ९९, २; १०५, २; ११३, ४; **१०.** ३२, ३; १३५, ७.

परिंऽकृतं **९.** ६१, १३; ८६, २४; **१०.** ८५, ६; १०७, १०.

परिंऽकृतस्य **८.** १, २६.

परिंऽकृतासः **९.** ४६, २.

परिऽक्रोशं **१.** २९, ७.

परिऽक्षिता **३.** ७, १; **१०.** ६५, ८.

परिऽक्षितोः **१.** १२३, ७.

परिऽगत्यं **२.** १५, ४.

परिंऽगधिता **१.** १२६, ६.

परिऽचक्ष्यं **७.** १००, ६.

परिऽचक्ष्याणि **६.** ५२, १४.

परिंऽछिन्नाः **७.** ३३, ६.

परिऽजभ्रुराणः **१.** १४०, १०.

परिंऽज्मन् **१.** ६३, ८; ११७, ६; **२.** २८, ४; ३८, २; **४.** २२, ४.

परिऽज्मन् १. ६, ९.
परिंऽज्मनः ३. २, ९.
परिंऽज्मने ४. ३, ६.
पारिंऽज्मनोः १. ४६, १४.
पारिंऽज्मा १. ७९, ३; ११२, ४; १२२, ३; ४. ४५, १; ५. ४१, १२; ७. १३, ३; ४०, ६; १०. ३९, १; ९२, ५; ९३, ४; ७.
परिंज्माऽइव ६. २, ८; १३, २.
परिंऽज्मानः ५. १०, ५.
परिंऽज्मानं १. २०, ३; ८. ७२, १०; १०. ४१, १.
परिंज्मानंऽइव १. १२७, २.
परिंज्मानाऽइव १०. १०६, ३.
परिंऽज्रयः १. ६४, ५; ५. ५४, २[२].
परिऽतंसयध्यै १. १७३, ७; ६. २२, ७.
परिंऽतक्म्या ५. ३०, १४; १०. १०८, १.
परिंऽतक्म्यायाः ५. ३०, १३.
परिंऽतक्म्यायां १. ११६, १५; ४. ४१, ६; ४३, ३; ५. ३१, ११; ६. २४, ९; ७. ६९, ४.
परिंऽतक्म्ये १. ३१, ६.
परिंऽतसं १. ११९, ६.
परिऽतप्यं १०. १६७, १.
परिऽदाम्यं १. १०५, २.
परिऽदीयथः ८. ५, ८; २६, ६.
परिंऽद्वेषसः ८. ७५, ९.
परिऽधयः १०. ९०, १५.
परिऽधावसि ९. २४, ५.
परिऽधिः १. १२५, ७; १०. १३०, ३.
परिऽधिं ३. ३३, ६; ४. १८, ६; ७. ३३, ९; १०. १८, ४.
परिऽधीन् ९. ९६, ११; १०७, १९; १०. १३९, ४.
परिधीन्ऽइव १. ५२, ५.
परिऽनशे १. ५४, १.
परिऽनष्टं १. २३, ८.
परिंऽपतिं ६. ४९, ८.
परिऽपदं १०. २८, १०.
परिपदांऽइव ८. २४, २४.
परिऽपंथिनः १०. ८५, ३२.
परिऽपंथिनं १. ४२, ३.
परिपंथीऽइव १. १०३, ६.
परिऽपश्यंति १. १६२, १२.
परिऽपानं ५. ४४, ११.
परिंऽपूतः १. १३५, २; ८. २, २.
परिऽप्रयंतं ९. ६८, ८.
परिऽप्रयाथ ४. ५१, ५.
परिऽप्रस्यंदंते ९. १०१, २.
परिऽप्रियः ९. ७२, १.
परिंऽप्रीतः १. १९०, ६.
परिंऽप्रीता १०. २७, १२.
परिऽप्रुषः १०. ७७, ५.
परिऽबभूव १०. ८८, १४.
परिऽबाधः ५. २, १०; ८. २४, ५.
परिऽबाधमानः ६. ७५, १४.
परिऽभुजत् १. १००, १४.
परिऽभुवः १. १६४, ३६.
परिऽभूः १. १, ४; ५२, १२; ९१, १९; ९७, ६; १४१, ९; २. २४, ११; ३. ३, १०; ४. ५३, ५; ५. १३, ६; १०. १२, २.
परिऽभूतमं १०. ९१, ८.
परिंभूतिऽभिः ७. ६६, १०.
परिऽभूषति १. १३६, ५.
परिऽभ्वे २. १६, ३.
परिऽमंसते ७. ५९, ३.
परिऽमन्यवे १. ३९, १०.
परिऽममृशुः ८. ९, ३.
परिमम्नाथे इति परिऽमम्नाथे ७.९३,६.
परिऽमर्धिषत् ८. ६१, ६.
परिंऽमिता १. १६४, ४५.
परिंऽयत्ताय ७. ८३, ८.
परिऽयन् १. १७३, ११; ९. ६८, २; ७१, ९; १०. ९२, ५; १२२,३;६.
परिऽयंतं ९. ६८, ६.
परिऽयाति ७. ६९, ५; ९. १११, १.
परिऽयाथः १. ११२, १३.
परिऽयासि १. १२१, ९; ६. ३७, ४.
परिऽरपः २. २३, ३; १४.
परिवत्सरीणं ७. १०३, ८.
परिवत्सरे १०. ६२, २.
परिऽवर्गं १. १२९, ८.
परिऽवर्तमाने १. १६४, १३.
परिऽविषे १०. ६२, १०.
परिंऽविष्टं १. ११६, २०; १०. ६८, ६.
परिंऽविष्टी ४. ३३, २.
परिंऽवीतः १. १२८, १; १६४, ३२; ३. ८, ४; ४. १, ७; ३, २; १०. ६, १; ४६, ६.
परिंऽवीतं १. १३०, ३.
परिवृक्ताऽइव १०. १०२, ११.
परिऽवृजं ८. २४, २४.
परिऽवृणक्षि १. १२९, ३.
परिंऽवृतं २. २३, १८; ४. ४५, २; ७. २७, २; १०. ११३, ६.
पारिंऽवृताः १. १३०, ३[२]; १४४, २; २. १७, १.
परिऽव्यत २. १७, २.
पारिंऽशक्तवे ८. ७८, ५.
परिऽशयानं ३. ३२, ११.
परिंष्टिः १. ६५, २; ८. ८८, ६.
पारिंष्टिषु १०. १४७, ३.
परिंष्टौ ७. १९, ७.
परिऽसदः ३. ३३, ७.
परिऽसदंतः ४. २, १७.
परिऽसद्यं ७. ४, ७.
परिऽसद्वानः १०. ६१, १३.
परिऽसस्वजाना ६. ७५, ३.
परिंऽसिक्तः २. १८, ६.
परिंऽसिक्तं ४. १, १९; ३५, ९; ६. ६८, ११; १०. ११६, ४.
परिंऽसिक्ता १. १७७, ३; ७. २४, २.
परिंऽसिक्तेभिः १. १०८, ४.
परिऽसिच्यमानः ९. ६८, १०; ९७, १४; ३६.
परिऽसिच्यमानाः ९. ९७, २६.
परिऽसिच्यसे ९. ६५, ६.
परिंऽसूताः १. ५३, ८.
परिंऽसूतिः ९. ८५, ८.
पारिंऽसूतेः १. ११९, ६.
परिंऽस्तुतिः ५. ८१, १.
परिऽस्तुभः १. १६६, ११; ९. ६२, २४.
परिऽस्तोभंत्या ९. ६४, २८.
परिऽस्थाः १०. ९७, १०.
परिऽस्थां ६. ७२, ३.
परिंऽस्थितं ६. १७, १२.

परिऽस्थिताः २. ११, २; ४. १९, ८; ७. २१, ३.
परिऽस्पृधः ९. ५३, १.
परिऽस्रुतः ८. ३९, १०.
परिऽस्रुतं ९. १, ६; ६८, १.
परिऽस्वजंत् ६. ६०, १०.
परिऽस्वजे १०. ४०, १०.
परिऽहितं १. १२१, १०.
परिऽहिनोमि ७. १०४, ६.
परिऽहुत ६. ४, ५.
परिऽह्वृता ८. ४७, ६.
परिऽह्वृतिः ७. ८२, ७.
परिऽह्वृतिं ९. ७९, २.
परीणसः १. ५६, २; १३३, ७; ८. २१, ७; ८४, ७.
परीणसं ३. २४, ५.
परीणसं ९. ९७, ९.
परीणसा १. १२९, ९; १६६, १४; ४. ३१, १२; ५. १०, १; ८. ७७, ९; ९७, ६.
परीमणि ९. ७१, ३.
परुः १०. १००, ५.
परुःऽपरुः १. १६२, १८; १०. ९७, १२.
परुषः १०. ५३, १.
परुषा ९. १५, ६.
परुषाः ५. २७, ५.
परुषि ७. ५०, २.
परुषे ६. ५६, ३.
परुष्णि ८. ७४, १५; १०. ७५, ५.
परुष्णीं ४. २२, २; ७. १८, ८; ९.
परुष्णीषु ८. ९३, १३.
परुष्ण्यां ५. ५२, ९.
परे १. १६४, १२; १६६, १३; २. १२, ८; ४. २५, ८.
परे ८. ६१, १७.
परेण १. १६४, १७; १८.
परेयिऽवांसं १०. १४, १.
परेषां १०. १२८, ६.
परेषु १. १२८, ३; ३. ५४, ५; १०. ५६, ७; ११४, २.
परैः १०. १५, १०.
पर्चैः ७. १००, २.
पर्जन्य ५. ६३, ४.
पर्जन्य ५. ८३, ५; ९; १०. १६९, २.
पर्जन्यः ४. ५७, ८; ५. ६३, ६; ८३, २-४; ६. ५२, ६; ७. ३५, १०; १०२, २; ८. ६, १; ९. २, ९; ८२, ३; १०. ६६, ६.
पर्जन्यःऽइव १. ३८, १४; ८. २१, १८.
पर्जन्यऽक्रंदं ८. १०२, ५.
पर्जन्यऽजिन्विताः ७. १०३, १.
पर्जन्यं ५. ५३, ६; ८३, १; १०. ९८, १; ८.
पर्जन्यऽरेतसे ६. ७५, १५.
पर्जन्यवाता ६. ४९, ६.
पर्जन्यऽवृद्धं ९. ११३, ३.
पर्जन्यस्यऽइव ९. २२, २.
पर्जन्याः १. १६४, ५१.
पर्जन्याय ७. १०१, ५; १०२, १.
पर्जन्यावाता ६. ५०, १२; १०. ६५, ९.
पर्जन्येन १. ३८, ९.
पर्णं १. ११६, १५; ४. २७, ४; ४०, ३.
पर्णंऽइव १०. १८, १४.
पर्णयऽघ्ने १०. ४८, ८.
पर्णयं १. ५३, ८.
पर्णवीःऽइव ९. ३, १.
पर्णा १. १८२, ७; १०. ६८, १०.
पर्णिनः ६. ४६, ११; ८. ५, ३३; ९. ८२, ३.
पर्णिना ८. १, ११.
पर्णे १०. ९७, ५.
पर्णेभिः ९. ११२, २.
पर्णैः १. १८३, १.
पर्तृऽभिः ६. ४८, १०; ७. १६, १०.
पर्फरत् १०. १०६, ७.
पर्फरीका १०. १०६, ६.
पर्व १. ६१, १२; ४. १९, ९; ७. १०३, ५; १०. ८९, ८.
पर्वणः १०. ६८, ९.
पर्वणाऽपर्वणा १. ९४, ४.
पर्वणिऽपर्वणि १०. १६३, ६.
पर्वतः १. ३७, ७; ५२, २; ५४, १०; २. ११, ७; ८; २३, १८; ५. ४५, ३; ६०, २; ३; ६. ४९, १४; ८. ७०, ११[2]; १०. १५८, ३.
पर्वतःऽइव १०. १७३, २.
पर्वतऽच्युतः ५. ५४, ३.
पर्वतऽच्युते ५. ५४, १.
पर्वतं १. ५५, ३; ५७, ६; ८५, १०; २. २४, २; ५. ३२, १; ५६, ४; ८. ६४, ५; १०. ३९, १३.
पर्वतऽवृधः ९. ४६, १.
पर्वतऽवृधं ९. ७१, ४.
पर्वतस्य २. १५, ८; ४. २१, ८; ५५, ५; ५. ३२, २; ३६, २; ४५, ३; ५९, ७; ६. २४, ६; ३०, ५; ७. ३७, ८; ७०, ३; ८. ३, १९; १०. ६८, ७.
पर्वतस्यऽइव ३. ५७, ६.
पर्वताः २. १२, १३; ३. ३५, ८; ५६, १; ५. ४१, ९; ५४, ९; ५५, ७; ६. ३०, ३; ७. ३४, २३; ३५, ८; ८. ७, २; ३४; ९६, ५; १०. १७३, ४.
पर्वताः १०. ९४, १.
पर्वताःऽइव १. ६४, ३.
पर्वतात् ४. ३०, १४; ५. ४३, ११; ७६, ४.
पर्वतान् १. १९, ७; ३९, ५; ६४, ११; ११६, २०; १६६, ५; २. १२, २; १७, ५; ३. २६, ४; ५. ४६, ३; ५७, ३; ६. २१, ९; ८. ७, ४; २३; १०. ३५, २; ३६, १; ५८, ९; ६४, ८; ६५, ११.
पर्वतानां १. ३२, १; ३९, ३; १५५, १; १८७, ७; ३. ५, ४; ३३, १; ४. १९, ४; ५. ८४, १; ८. १८, १६; १०. ८९, १०.
पर्वतासः ३. ३०, ४; ५४, २०; ४. १७, २; ५. ४६, ६; ८५, ४; ८७, ९; ६. ३१, २; ५२, १; ४; ८. १५, ८; २०, ५; ५४, ४; ६३, १२; १०. २७, ५; ८९, १३.
पर्वते १. ३२, २; ५१, ४; ५७, २; २. २८, ८; १०. २७, ४.
पर्वतेन ६. २२, ६; ७. १०४, १९; १०. १८, ४.
पर्वतेभिः ४. ३४, ८.

पर्वतेभ्यः १. १९१, ९; ४. ५४, ५; ७. १०४, ४; ८. ३४, १३; १०. ६८, ३.
पर्वतेषु १. ५९, ३; ८४, १४; ९१, ४; १०८, ११; २. १२, ११; ५. ६१, १९; ६. ६४, ४; ८. ७, १; २०, २५.
पर्वतेऽस्थां ६. २२, २.
पर्वतैः २. १६, ३.
पर्वत्यां १०. ६९, ६.
पर्वऽभिः १०. ७९, ७.
पर्वऽशः १. ५७, ६; ८. ६, १३; ७, २२; २३; १०. ७९, ६.
पर्वऽसु ८. ४८, ५.
पर्वाणि ४. २२, २; १०. ८७, ५.
पर्शवः १. १०५, ८.
पर्शानासः ८. ७, ३४.
पर्शाने ७. १०४, ५; ८. ४५, ४१.
पर्शुः १०. ८६, २३.
पर्शौ ८. ६, ४६.
पर्ष १. ९७, ८.
पर्षणि १०. १२६, ३.
पर्षणिं १. १३१, २.
पर्षत् ३. २०, ४; ५. २५, ९; ७. ९७, ४; १०. ६१, १; ६३, ६.
पर्षत् १. ९९, १; १८६, ३; ७. ६८, ७; ८. ६७, २; १०. ६१, २३; १८७, १.
पर्षति ५. २५, १.
पर्षथ १. ८६, ७.
पर्षथ ८. ८३, ३.
पर्षथः ५. ७३, ८; ८. २६, ५; १०. १४३, ४.
पर्षन् ४. ३९, १; ७. ४०, ४; ६०, ७.
पर्षान् १०. ४८, ७.
पर्षि १. १७४, ९; २. ७, २; ३३, ३; ३. १५, ३; ६. ४, ८; ४८, १०; ८. ६७, ११; १०३, ७; ९. १, ३.
पर्षि १. १२९, ५; ५. ३, ११; ४, ९; ७. २३, २; ८. ९७, १५; ९. ७०, १०.
पर्षिष्ठाः १०. १२६, ३.
पलस्तिऽजमदग्नयः ३. ५३, १६.
पलिक्नीः ५. २, ४.
पलितः १. १४४, ४; ३. ५५, ९; १०. ४, ५; ५५, ५.
पलितस्य १. १६४, १.
पव ९. ४९, ३.
पवतां ९. ३६, ५.
पवतां १०. १२८, २.
पवते ९. ३६, ४; ६५, २५; १०६, १३.
पवते २. १६, ५; ६. ८, १; ९. ३, १०; ६, ७; ८; २५, ५; ४२, २; ६१, २५; ६२, १४; ६३, १३; ६७, ८; ११; १२; ६९, ३; ६; ७१, ३; ७२, ४; ५; ७; ७५, १; २; ७६, १; ४; ७७, २; ५; ७८, ४; ८०, १; ३; ८४, ३–५; ८५, ४; ८६, ७; ९; १०; १३; १९–२१; ३३; ४५; ८७, २; ८; ८८, १; ८९, ६; ९४, १; ९६, ५; ९७, ५; १०–१२; २३; ४६; ५६; १०१, ५; ६; १६; १०६, २; १०७, ७; १७; १०८, ५; ११०, ११; १०. १५४, १.
पवध्वं ९. २१, ६.
पवंतां ९. १३, ५; ६४, ६; ६५, २४.
पवंते ७. २८, ४; ९. १३, ३; २३, ४; ४२, ३; ६४, ५; १०७, १४; १०. ३, ५.
पवंते ४. ५८, ९; १०; ६. १०, २; ४१, १; ९. ७, ८; १०१, १०.
पवमान ९. ४, १; ९; ९, ९; ११, ९; १३, ८; १९, ६; २५, २; २६, ६; ३५, १; ३६, ३; ४३, ४; ५९, ४; ६१, १८; २६; ६३, ११; २३; ६४, ९; ६५, २; ४; ११; ६६, ३; ३०; ६७, २१; ८६, ३४; ३८; ९४, ५; ९७, ३१; १००, ७–९; १०१, ९; १०७, २१; १०८, ३.
पवमान ९. ५, १०; १२, ९; २३, ३; २४, ३; ४०, ४; ६५, ३; ६६, २; ७२, ९; ७४, ९[२]; ७९, ३; ५; ८५, २; ८६, १; ४; २८–३०; ३५; ९०, ५; ९२, ४; ९३, ४; ९६, ४; ११; २३; १०७, २२; ११०, २; ३; ९; ११३, ६; ७.
पवमानः ८. १०१, १४; ९. ३, २–५; ७; ८; ५, १–४; ६; ७; ९; ७, ५; २०, २; २७, ४; ५; २८, ५; ३०, ४; ३७, ३; ४; ४९, ५; ५९, ३; ६०, ३; ६१, १६; ६२, १०; ११; १६; ३०; ६३, ८; ६५, १६; ६६, २०; २२; २४; २६; २७; ६७, २२; ६९, २; ७६, ३; ७८, ५; ८०, ५; ८१, ३; ४; ८५, ८; ८६, ८; १२; १३; १८; ८८, ५; ८९, १; ९१, ३; ९६, ७; ८; २१; ९७, १४; २४; ४१; ४४; १०३, ६; १०६, १०; १०७, ११; १५; २२; ११०, १०.
पवमानं ९. १३, २; २६, ३; ४६, ६; ५०, ३; ६०, १; ६७, ९; ७८, ३; ८१, ५; ८६, २४; ९७, ८.
पवमानस्य ९. ५, ८; ११; ४१, ३; ५१, ३; ५३, ३; ६१, ४; १७; ६४, ७; २४; ६६, १०; २५; ८१, १; ८६, ६; ९२, ५; ९६, २४; ११४, १.
पवमानाः ९. १३, ९; ६३, २५; २७; ८५, ७; ८७, ५; १०७, २५.
पवमानाय ९. ११, १; ६५, ७; ८६, ४४.
पवमानासः ९. २१, ४; २४, १; ३१, १; ६३, २६; ६७, ७; ६९, ९; १०१, ८.
पवमानेन ९. ५, ५; ९७, ५८.
पवयः १. ३४, २; १३९, ३; १८०, १; ५. ३१, ५; १०. २७, ६.
पवया ९. ९७, ५३.
पवसे ९. २०, ३; ९७, ३१.
पवसे ९. २३, ६; ६३, २४; ६६, १९; ७६, ५; ८०, २; ८५, ३; ८६, ५; २३; ९७, ३२.
पवस्ते इति १०. २७, ७.
पवस्व ९. १, १; २, १; ११, ७; १३, ४; २४, ४; ६; २५, १; २९, ४; ३०, ३; ३५, २; ३६, २; ४२, ६; ४३, ६; ४९, १; ५२, ५;

५५, ३; ५९, १; २^{३}; ६१, २८; ६२, २५; २६; ६३, २२; ६४, २२; ३०; ६५, १३; ६६, १; ४; २१; ६७, १; १३; १६; ७०, ९; ८४, १; ८६, १८; २२; ४८; ९६, १३; २१; १००, ५; ६; १०६, ५; ७; १०७, २३; १०८, १; १५; १०९, ४; ७; १०.

पवस्व ९. २, ९; ६, १; ८, ७; ११, ३; २५, ६; २९, ६; ३३, ६; ३५, १; ४०, ३; ४१, ४; ५; ४४, ४; ४५, १; ६; ४६, ५; ४९, २; ३; ५०, ५; ५५, ४; ६०, ४; ६१, ९; १९; २२; ६२, १२; ६३, १; ७; १८; ६४, १३; ६५, ३; ५; १०; १२; १५; २१; २७; ६६, १५; ६७, ३०; ६८, १०; ६९, ८; १०; ७०, १०; ७२, ८; ८०, ४; ८२, ५; ८५, ६; ८६, ३८; ३९; ८८, ७; ८९, ७; ९०, ३; ४; ६; ९६, ३; ४; १२; १४; ९७, १५; १६; २७–३०; ३६; ४३; ४४^{३}; ५२; ५३; १०६, १४; १०८, १०; १०९, ५; ६; ११०, १२; ११३, २.

पवा ९. ९७, ५२.

पवाते ९. ९७, ४.

पविः ५. ६२, २; ६. ५४, ३.

पवितारः ९. ४, ४.

पवितारे ९. ८३, २.

पवित्रं १. १३५, ६; ८. १, १५; ९. २, १; २०, ७; २४, ५; २५, ६; ४५, ४; ४९, ४; ५१, ५; ६१, ४; ५; ६२, १; ७; ३०; ६३, १५; ६६, ५; २८; ६७, ७; १९; २०; २३; २४; ६८, २; ६९, ९; ८३, १; २; ८५, ९; ८६, ७; ९६, ६; १७; ९७, १; १०६, १४; १०७, २५; १०९, १६; १९; १०. ३१, ८.

पवित्रऽरथः ९. ८३, ५; ८६, ४०.

पवित्रऽवंतः ९. ७३, ३; १०१, ४.

पवित्रऽवंता १०. २७, १७.

पवित्रऽवान् १. १६०, ३.

पवित्रस्य ८. ३३, १.

पवित्रा ९. ७३, ८; ९७, ५५.

पवित्रात् १०. १७, १२.

पवित्रे १. २८, ९; ८. १०१, ९; ९. २, ५; ३, ९; ६, ३; १२, ५; १६, ३; ४; ७; १७, ३; ४; १८, १; २७, १; २; ५; २८, २; ३०, १; ३६, १; ३७, १; २; ३९, ३; ४; ४२, ४; ४३, ५; ४४, ३; ५१, १; ५२, १; ५६, १; ६१, ८; ६२, २१; ६३, १६; ६४, ११; १२; ७३, ७; ९; ८५, १०; ८६, ३; ६; २२; २३; ३०; ८७, ४; ७; ९२, १; २; ९७, ४०; ९८, ११; ९९, ८; १००, ६; ७; १०१, १५; १०९, १२.

पवित्रेण ९. ६७, २२; २५.

पवित्रेभिः ९. ८७, ५; ९७, २४.

पवित्रैः ३. १, ५; २६, ८; ३१, १६; ३६, ७.

पविऽभिः १. ६४, ११; ७. ६९, १.

पविऽभ्यः १. १६८, ८.

पविं ९. ५०, १; १०. १८०, २.

पविषु १. १६६, १०.

पविष्ट ९. ६४, १०; १०९, १३.

पवीरवान् १०. ६०, ३.

पवीरवि ८. ५१, ९.

पवीरवस्य १. १७४, ४.

पव्यया ९. ८६, ३४.

पव्या १. ८८, २; ५. ५२, ९.

पव्याऽइव ६. ८, ५.

पशवः ३. ९, ७; ८. १००, ११.

पशवे ३. ६२, १४.

पशव्यं ७. ९८, ६.

पशुं ३. ५३, २३.

पशुऽइव १०. ४, ३.

पशुऽइषे १. १२१, ७.

पशुः १. ६५, ५; २. ४, ७; ३८, ८; ५. ७, ७; ९, ४; ५०, ४; ६. २, ९; ७. १८, ८; ८७, २; ८. १, ३१.

पशुऽतृप ७. ८६, ५.

पशुना १०. ८७, १६.

पशुऽपाः ४. ६, ४; ६. १९, ३; ५८, २.

पशुपाःऽइव १. ११४, ९; १४४, ५; १०. १४२, २.

पशुऽभ्यः १०. ८५, ४४.

पशुं १. २३, १३; ८३, ४; ११६, २३; ५. ७, १०; ६१, ५; ८. १८, ६; २७, २; ३४, १६; ४५, १६; ९. ८६, ४३; १०. २३, ६; २५, ६; ४६, २; ४८, ४; ९०, १५.

पशुऽमत् ४. ३८, ५; ९. ७२, ९.

पशुऽमत्यै ५. ४१, १७.

पशुऽमंति ९. ९२, ६; ९७, १.

पशुऽमान् ३. ५४, १८.

पशुऽरक्षिः ६. ४९, १२.

पशुऽवर्धनाय ९. ९४, १.

पशुऽसः ५. ४१, १.

पशुऽसाधनी ६. ५३, ९.

पशुऽसे १. १२७, १०.

पशून् १. ७२, ६; ९२, १२; १८८, ९; ७. १३, ३; १०. ९०, ८.

पशौ ९. ९९, ६.

पश्चा १. १२३, ५; २. २७, ११; ४. १, १८; १०. ६१, १२; १८; ६७, ११; १४९, ३; १७१, ४.

पश्चात् १. ११५, २; १२४, ९; १६३, १२; २. ४१, ११; ६. १९, ९; ७५, ६; ७. ५६, २१; ८. ६१, १५; १६; ८०, ४; १००, १; १०. ३, ३; ४२, ११; ८७, २०; २१; ९०, ५; ११७, ८; १३५, ६.

पश्चातात् ७. ७२, ५; ८. ४८, १५; १०. २७, १५; ३६, १४.

पश्यं ८. १००, ४.

पश्य ३. २३, २; ६. ४७, ७; १०. ५५, ५; ८५, ३५; ८७, १०; १०२, ९.

पश्यत् १. १६४, १६.

पश्यंत ४. २६, १; ६. ९, ४; १०. ८५, ३३.

पश्यत १. २२, १९; १०३, ५; १०. १७९, १.

पश्यंतः ८. २५, ७.

पश्यति ३. ६२, ९; ७. ५५, ६; ८. ७८, ५.

पश्यति १. २५, ११; ८. ६, २९; ९. ९, ६; १०, ९; ७३, ८.

पश्यते ९. ७०, ४; ७१, ९.

पश्यंत्ऽभ्यः १. ११३, ५.
पश्यथ १. १०५, १६; १०. १३६, ३.
पश्यन् १. ३५, २; ५०, ७; ८८, ५; ११६, २५; १७४, ६; ४. १, १७; ५. ५३, ३; ६. ९, ३; ५१, २; ७. ६०, २; ९. ९६, ७; १०. १६, १०; ७१, ४; १२३, ८; १२४, ३; १३०, ६.
पश्यंतः १. ५०, १०; १४७, ३; ४. ७, ३; ८. २०, २६.
पश्यंति १. २२, २०; २३, २; १३२, ३; २. २७, ३; ३. ३८, ९; ५. २, १; ७. ७८, ४; ८७, ३; ८. ६, ३०; १०. १७७, १.
पश्यमानासः ७. ८३, १; ९. ११०, ६.
पश्यसि १. ५०, ६; ७. ९८, ६; १०. ८७, ६; १२.
पश्यसि १. ९४, ७; ६. ५२, ३.
पश्यस्व ८. ३३, १९.
पश्यात् १०. ७२, १.
पश्यात् ४. २५, ४.
पश्यान् १. ११३, ११.
पश्यामसि १. १५२, ४.
पश्यासि १०. १४, ७.
पश्येः ४. २, १२.
पश्येत १०. ११७, ५.
पश्येम ६. ५२, ५; ७. ६६, १६; ८. ४, ७; १०. ५९, ४.
पश्येम १. ८९, ८; ९. ४, ६; १०. ३७, ७; ८; ५९, ६; १५८, ४; ५.
पश्वः १. ६७, ३; १६६, ६; ३. ५४, १५; ४. २, १८; ६, ३; ५. २, ५; ३०, १५; ३१, १; ६. १, १२; १३, ५; १९, ३; ८. ४१, १; ६३, ९; ९६, १०; १०. १००, १२.
पश्वःऽइष्टिः १. १८०, ४.
पश्वऽयंत्रासः ४. १, १४.
पश्वा १. ६५, १; १०. ६१, १२.
पश्वाऽइव १०. १०६, ३.
पश्वे १. ४३, २; ८. ५, २०; १०. ३५, १२.
पस्त्यं १०. ९६, ११.
पस्त्यऽवत् २. ११, १६.
पस्त्यऽवतः १. १५१, २; ४. ५४, ५.
पस्त्यऽवति ८. ७, २९.
पस्त्यऽवान् ९. ९७, १८.
पस्त्युऽसदः ६. ५१, ९.
पस्त्यानां १. १६४, ३०; ६. ४९, ९; ७. ९७, ५; ९. ६५, २३.
पस्त्याभिः १. ४०, ७.
पस्त्यां ४. ५५, ३.
पस्त्यासु १. २५, १०; ४. १, ११; १०. ४६, ६.
पस्त्ये ८. २७, ५.
पस्त्योः १०. ९६, १०.
पस्पर्शत् ४. ४१, १.
पस्पशानः १०. १०२, ८.
पस्पशे १. २२, १९.
पस्पशे १. १२८, ४.
पस्पृधाते इति ७. १०४, १२.
पस्पृधानं १. ६१, १५.
पस्पृधानासः १. ११९, ३; ७. १८, ३.
पस्पृधानेभ्यः २. १९, ४.
पस्पृध्रे ६. ३४, १.
पांसुरे १. २२, १७.
पाः ४. २०, ४.
पाकः १. १६४, ५; १०. ७, ६; २८, ५.
पाकऽत्रा ८. १८, १५; १०. २, ५.
पाकऽदूर्वा १०. १६, १३.
पाके १. ३१, १४; १६४, २१.
पाकऽवत् १०. १००, ३.
पाकऽशंसं ७. १०४, ९.
पाकऽसुत्वनः १०. ८६, १९.
पाकऽस्थामा ८. ३, २१; २२.
पाकऽस्थामानं ८. ३, २४.
पाकाय ३. ९, ७; ४. ५, २.
पाकेन ७. १०४, ८; १०. ११४, ४.
पाक्या १. १२०, ४; २. २७, ११; १०. २५, ३.
पाजः १. ११५, ५; ३. १४, १; २९, ३; ६१, ५; ४. ४, १; ५. १, २; ६. २१, ७; ७. ३, ४; १०, १; ९. ६८, ३; १०. ८४, ३.
पाजसः १०. ३७, ८.
पाजसा १. ५८, ५; १५१, १; २. २४, १३; ३. १५, १; ४. ४८, ५.
पाजसी इति १. १२१, ११.
पाजसे ८. ४६, २५; ९. १०९, २१.
पाजस्वंतः १०. ७७, ३.
पाजांसि ९. ७६, १; ८८, ५.
पांचऽजन्यः १. १००, १२; ९. ६६, २०.
पांचऽजन्यं १. ११७, ३; ५. ३२, ११.
पांचऽजन्यया ८. ६३, ७.
पांचऽजन्यासु ३. ५३, १६.
पांचऽजन्येन ७. ७२, ५.
पाणिऽभिः २. ३१, २.
पाणी इति ४. २१, ९; ६. ७१, १.
पात ४. ५५, ५; ८. ३१, २.
पात ४. ३५, ४.
पात १. ४५, १०; ४. ३४, ६; ७. १, २०; २५.
पातः १. १३६, ५.
पातं १. ४६, ५; ४७, ३; ५; ९३, ८; १२०, ४; ७; १५३, ४; ३. ६२, १८; ५. ७०, ३; ७. ९१, ६; ८. ४२, २; ५७, २; ८७, १.
पातं १. ११२, २५; २. ३९, ४; ३. १२, १; २; ५८, ९; ४. ५६, ४; ७. ९१, ४; ८. ४०, १२; ८७, २; १०. ९३, १[२].
पातयति १. ४८, ५.
पातयंते ८. ४६, १८.
पातल्येऽइति ३. ५३, १७.
पातवे १. २८, ६; १०८, २; ११६, २२; २. १६, ५; ६. ५७, २; ८. ६९, १०; ९. १, १; ९; ४, ४; ११, ८; १६, ३; २४, ३; ५१, १; १००, ५; १०८, १५.
पातवै ३. ४६, ५.
पाता ६. २३, ३; ८. २, २६.
पाता २. २०, ३; ८. ९३, ३३.
पाता १. १८५, १०.
पाति ३. ५, ५[४]; ४. ५, ८; ८. ५९, ३; ९. ८३, ४.
पाति ३. ५५, १०; ४. १३, ५; ५. १२, ६; ४७, ३; ९. ६, ८; ७१, १; ८९, ३; १०. १, ३.
पातु १. १८, ५; ९८, २; १०६, ७; ५. १५, ५; ५१, १३; ६. ६१,

११; ७५, १०; १४; ७. १५, ३; ३८, ३; ५; १०१, ६; १०४, २३; ८. १८, ६; ६१, १५; ९७, १५; १०. ११, २; १७, ४; १८, १०; ३६, ३; ३७, २; ४२, ११; ६३, १६; ६४, १०; ६६, ३; ११५, ५; १५८, १; १६४, ४.

पात्रं १. ८२, ४; ११०, ५; १२१, १; १७५, ३; २. ३७, ४; ६. ७, १; ४४, १६; १०. ५०, ६; ११२, ६.

पात्रंस्यऽइव १. १७५, १.

पात्रा १. १०४, ८; ८. १०३, ६; १०. ५३, ९.

पात्राऽइव ७. १०४, २१.

पात्राणि १. १६२, १३; १०. ४४, ५.

पात्रे १०. १०५, १०.

पात्रेण १०. १३६, ७.

पाथ १. ८६, १; १०. १२६, २.

पाथ १०. १२६, ४.

पार्थः १. १५४, ५; १६२, २; १८८, १०; २. ३, ९; ३. ८, ९; ३१, ६; ५५, १०; ६. १५, १२; ७. ५, ७; ३४, १०; ४७, ३; ६३, ५; १०. ७०, ९; १०; ९२, १५; ११०, १०.

पाथः १. १८०, ७; २. २, ४; ७. ९१, २.

पाथः १. १५९, ३.

पाथर्न १. १६६, ८.

पाथ्यः ६. १६, १५.

पार्दः १०. ९०, ३; ४.

पादुकौ ८. ३३, १९.

पादुऽगृह्य ४. १८, १२; १०. २७, ४.

पादें ७. ३२, २.

पादा १. २४, ८; ६. २९, ३; १०. ७३, ३.

पादाऽइव २. ३९, ५; १०. १०६, ९.

पादाः १. १६३, ९; ४. ५८, ३.

पादि ६. २०, ५.

पादि १. १०५, ३.

पादुः १०. २७, २४.

पादौ १०. ९०, ११.

पादौऽइव ६. ४७, १५.

पानः ९. ७०, ४.

पांर्तः ९. ९८, ८.

पांर्तं १. १२२, १; १५५, १; ७. ३३, २; ८. ९२, १; ९. ६५, २८; १०. ८८, १.

पांर्ता १. १२२, ४.

पांर्ति १. ४१, २; १६७, ८; ५. १८, ४; ५२, ४; ६७, ३; ८. २५, १३; ४६, ४.

पांति २. ११, १४; ५. १२, ४; १९, २; ५२, २; ७. ५६, १९; १०. ५, २; १७७, २.

पांतु २. ३, ८; ४. ४, १२; ७. ४०, ६; १०. १२८, ७.

पापंजे १०. १०५, ३.

पापतन् ८. २०, ४.

पापतीति ६. ६, ५.

पापऽत्वाय ७. ३२, १८; ९४, ३; ८. १९, २६.

पापं १०. १०, १२.

पापया १. २९, ५; ८. १९, २६; १०. ७१, ९; ८५, ३०; १३५, २.

पापस्य १. १२९, ११.

पापाः १. १९०, ५.

पापासः ४. ५, ५; ८. ६१, ११.

पापीः १०. १०८, ६.

पामि १०. २८, २.

पायनाय १. ११६, ९.

पाययं ३. ५७, ५.

पायय १. १४, ७; १२५, ३; २. ३७, ६.

पाययते १. ५६, १.

पायवः १. १४७, ३; ४. ४, १२; ५. १२, ४; ८. १८, २.

पायवे ६. ४७, २४.

पायुः १. ३१, १३; ८९, ५; २. १, ७; ४. २, ६; ४, ३; ६. ४४, ७; ७. ३७, ८; ८. ६०, १९; १०. १००, ९.

पायुऽभिः १. ३१, १२; ९५, ९; १३०, १०; १४३, ८; १८९, ४; ५. ४१, १५; ७०, ३; ६. ७१, ३; ७. ३८, ३; ८. २५, ११; २७, ४; ६०, ८.

पायुं २. २, ४; ६. १५, ८.

पायोः ३. १५, ४.

पारः ५. ३१, ८.

पारतः ४. ३०, १८.

पारं १. ४६, ११; ९२, ६; १२१, १३; १८३, ६; १८४, ६; २. ३३, ३; ३. ३१, २०; ५. ५४, १०; ७. ६०, ७; ८. १९, ३४; ९६, ११; १०. २९, ५; १६१, ३.

पारयं १, १७४, ९.

पारय १. ९७, ७; १८९, २; ९. ७०, ९.

पारयतं २. ३९, ४.

पारयथ २. ३४, १५.

पारयथः १. ११८, ६.

पारयंता ६. ६९, १; ७. ६९, ७.

पारयंति १. १८२, ६.

पारयंती ६. ७५, ३.

पारयात् १. १४०, १२.

पारयाति ८. १६, ११.

पारयामसि १०. ९७, २२.

पारयिष्णवः १०. ९७, ३.

पारार्य १. ४६, ७.

पारावतऽघ्नीं ६. ६१, २.

पारावतं ८. १००, ६.

पारावतस्य ८. ३४, १८.

पारावताः ५. ५२, ११.

पारिषत् १०. ९६, ८.

पारिपत् १. १००, १४.

पारे १. ३३, ७; ५२, १२; ११६, ४; १६७, २; २. ११, ८; ६. ६९, १; ८. ५९, २; १०. २७, ७; ४९, ६; १४३, ५; १५५, ३; १८७, ५.

पार्थवाना ६. २७, ८.

पार्थिवः ७. ३२, १७; २३; ८. ५१, ८; १०. ८५, ४.

पार्थिवं १. ३८, १०; ८७, ५; ९०, ७; १२८, ३; ५. ८७, ७; ८. ८८, ५; ९. १९, १; २९, ६; ७२, ८.

पार्थिवस्य **१.** ११३, ७; १४४, ६; **२.** १४, ११; **५.** ४१, १; ६८, ३; ६९, ४; **६.** २२, ९; **७.** ९७, १०.

पार्थिवा **१.** ६४, ३; **४.** ५३, २; **५.** ८, ७; **६.** १६, २०; ४५, २०; ५९, ९; **९.** १४, ८; ३६, ५; ६३, ३०; ६४, ६; ९७, ५१; १००, ३; **१०.** १११, १०.

पार्थिवाः **५.** ५२, ७; **७.** ३५, ११.

पार्थिवात् **१.** ६, १०; **७.** १०४, २३.

पार्थिवानां **१.** ९५, ३.

पार्थिवानि **१.** ३४, ६; १५४, १; १५५, ४; **५.** ४१, १४; ८१, ३; **६.** ६, ६; २२, ८; ३१, २; ४९, १३; ६१, ११; **८.** ९४, ९; **१०.** ३२, २.

पार्थिवाय **१०.** ७६, ८.

पार्थिवासः **५.** ४६, ७; **६.** ३६, १; ५०, ११; **७.** ३५, १४; **१०.** ६५, ९.

पार्थिवीः **८.** २५, ६.

पार्थिवे **१.** १६९, ६; **८.** ९७, ५; **१०.** १५, २.

पार्थिवेभ्यः **१०.** १५८, १.

पार्थिवेषु **१०.** ११६, ३.

पार्थ्यैः **१०.** ९३, १५.

पार्यै **१.** १२१, १२.

पार्याः **७.** २७, १.

पार्यात् **३.** ३२, १४.

पार्याय **४.** १६, ११; २५, १; **१०.** २७, १६.

पार्ये **६.** १७, १४; २३, २; २६, १; ३३, ५; ४०, ५; ६६, ८; **७.** ३२, १४; २१; ८३, ५; **८.** ९२, ९; **९.** १, ७.

पार्श्वात् **४.** १८, २.

पार्षद्वाणः **८.** ५१, २.

पार्ष्णिऽभ्यां **१०.** १६३, ४.

पार्ष्ण्यौ **१.** १६२, १७.

पार्वक **७.** १, ८.

पावक **१.** १२, ९; १०; १३, १; ५०, ६; ९५, ११; ९६, ९; **२.** ७, ४; **३.** १०, ८; २१, २; **४.** ५, ६; **५.** ४, ७; २३, ४; २६, १; **६.** २, ६; ४८, ७; **८.** ६०, ३; ११; ७४, ११.

पावकः **१.** ६०, ४; १४२, ३; **२.** ३, १; **३.** ५, ७; १७, १; २७, ४; **४.** ६, ७; **५.** ७, ४; **६.** ४, ३; ६, २; १०, ४; **७.** ३, १; ९; ९, १; १५, १०; **८.** १३, १९; **९.** २४, ६; ७; ९७, ७; **१०.** ४५, ७.

पावकं **१.** ६४, १२; **५.** ४, ३; **६.** १, ८; १५, ७; **८.** २३, १९; **१०.** ३६, ७; ४६, ४; ८.

पावकया **६.** ११, २; १५, ५; **९.** १०१, २.

पावकऽवर्चाः **१०.** १४०, २.

पावकऽवर्णाः **८.** ३, ३.

पावकऽशोचिषः **३.** ११, ७.

पावकऽशोचिषं **३.** ९, ८; **४.** ७, ५; **८.** ४३, ३१; ४४, १३; १०२, ११; **१०.** २१, १.

पावकऽशोचिषे **५.** २२, १.

पावकऽशोचे **३.** १, ६; **६.** १५, १४.

पावका **१.** ३, १०.

पावकाः **३.** ३१, २०; **४.** ५१, २; **७.** ४९, २; ३; ५६, १२; ५७, ५; **१०.** ४६, ७.

पावकान् **६.** ५१, ३; **८.** २०, १९.

पावकासः **१.** ६४, २; १४२, ६.

पावके **६.** ५, २.

पावके इति **६.** ४९, ३.

पावकेभिः **५.** ६०, ८.

पावमानीः **९.** ६७, ३१; ३२.

पावीरवी **६.** ४९, ७; **१०.** ६५, १३.

पाशऽद्युम्नस्य **७.** ३३, २.

पाशी **१.** २४, १५; २५, २१; **७.** ८८, ७.

पाशाः **२.** २७, १६; २९, ५.

पाशात् **६.** ७४, ४; **१०.** ८५, २४.

पाशान् **१.** २४, १३; **५.** २, ७; **७.** ५९, ८.

पाशिक्षः **३.** ४५, १; **९.** ७३, ४.

पाप्यौ **१.** ५६, ६.

पाप्योः **९.** १०२, २.

पासतः **७.** ३४, २३.

पासति **१०.** १७, ४.

पासिं **६.** ३, १; **७.** २८, २.

पासि **१.** ३१, १५; १३४, ५[२]; **२.** १, ६; ९; **५.** ३, ३; **६.** १५, ११; **७.** ५, ७; **८.** ५२, ७.

पास्त्यस्य **४.** २१, ६.

पाहि **१.** २७, ३; ३६, १५[२]; ५४, ११; १२१, १४; १२९, ९; ११; १७४, १; १८९, ४; **३.** ४०, ६; **४.** ४, १५; **५.** १७, ५; ३३, ७; **७.** १, १३[२]; ५४, ३; **८.** ३३, ४; ४८, १५; ६०, ९[४]; १०; ७१, १; **९.** ६४, १८; **१०.** ८३, २; ११५, ९; १५८, २.

पाहि **१.** २, १; ३६, १४; ६७, ३; ७०, ३; ७२, ६; ९१, १५; ९५, ९; १२९, ९; १३०, १०; १४३, ८[२]; १४७, ५; १७१, ६; **२.** ११, १५; १७; २८, १०; ३५, ६; **३.** १, १०; २०, २; ३१, २०; ३५, ६; ८; १०; ३६, ३; ३७, ८; ४०, १; ४७, ३; ५१, ७; ८; **४.** ३४, ७; **५.** ४, ६; ८; ४३, ३; **६.** ८, ७; १५, १२; १६, ३०; ३१; १७, २; ३; २४, १०[२]; ४०, ५; ४१, २; ४८, ८; ७१, ३; **७.** ३, ७; ८; ९८, २; **८.** १३, २१; ४४, ११; ६०, ८; ६१, १६; ८४, ३; **९.** ५६, ४; ८८, १; **१०.** १२, ६; २४, ३; २५, ८; ८७, २१; ९३, ११; १२८, ६; १६०, १; २.

पिंशत **१०.** ५३, ७.

पिंशति **१.** १६१, १०.

पिंशतु **१०.** १८४, १.

पिंशते **८.** १९, २२.

पिंपती **१.** १९१, २.

पिंगा **८.** ६९, ९.

पिठीनसे **६.** २६, ६.

पिणक् **३.** ३०, ८; **४.** १८, ९; ३०, ९; **६.** १७, १०; **८.** १, २८.

पिंडानां **१.** १६२, १९.

पितः १. १८५, ११.

पितः १. ११४, ९; २. ३३, १.

पितरः ६. ७५, १०.

पितरः १. ६२, २; ७१, २; ८९, ९; ९१, १; १०६, ३; १०९, ७; ३. ३९, ४; ५५, २; ४. १, १३; २, १६; ६. २२, २; ५२, ४; ५९, १; ७५, ९; ७. १८, १; ३५, १२; ७६, ४; ९. ६९, ८; ८३, ३; ९६, ११; ९७, ३९; १०. १४, २; ६; ९; १५, १[२]; ५; ८; १३; १७, ९; १८, १३; ५६, ४; ६; ६२, २; ६८, ११; ९४, १२; १३०, १; ६.

पितरः ८. ४८, १२; १०. १५, ४; ६; ७; ११; ५७, ५; ८८, १८.

पितरं १. २४, १; २; ११४, ७; १३०, १; १६३, १३; १६४, ८; १२; १८; २२; २. १, ९; २६, ३; ३३, १२; ३. २६, ९; २७, ९; ४. १८, १२; ५. ३, ९; ३४, ४; ५२, १६; ६. ४९, १०; ७. १८, २५; २६, २; ३२, ३; १०३, ३; ९. ८६, १४; १०. ७, ३; ४८, १; ५४, ३; ८८, १५; ९५, १२; १२४, ४; १२७, ७; १८९, १.

पितरा १. २०, ४; ११०, ८; १५९, २; १६१, १२; ३. ३, ११; ७, १; ५४, १६; ४. ३३, ३; ३४, ९; ३५, ५; ३६, ३; ७. ५३, २; ६७, १; १०. ११, ६; १२, ४; ३९, ६; ६१, १; ६५, ८.

पितराऽइव ३. १८, १; ५८, २; ४. ४१, ७; १०. १०६, ४.

पितरिं १०. ६१, ६.

पितरिति ६. ५१, ५.

पितरौ १. १२१, ५; १६१, १०; १०. ८५, १४; १३१, ५.

पिता १. २६, ३; ३०, ९; ३१, १०; १४; १६; ३८, १; ४६, ४; ६९, १; ८०, १६; ८९, ४; १०; ९०, ७, ११४, २; ११६, १६; १६०, २[२]; १६४, १६; ३३; १८५, १०; १९१, ६; २. ५, १; १७, ६; ३३, १३; ३. ३, ४; ३१, १; ४. १, १०; १७, १७; ५. ३, १०; ४, २; ४३, २; ६०, ५; ८३, ६; ६. १, ५; १६, ३५; ७०, ६; ७३, १; ७५, ५; ७. ३२, १९; २६; ५२, ३; ५५, ५; १०१, ३; ८. ५२, ५; ६३, १; ९८, ११; ९. ७३, ३; ७६, ४; ८२, ३; ८६, १०; ८७, २; ८९, २; १०९, ४; १०. १४, ५; २२, ३; ३४, ४; ६०, ७; ६१, ७; ६४, १०; ६७, १; ८१, १; ८२, १; ३; १००, ५; १३५, १; १३८, ६; १८६, २.

पिताऽइव १. १, ९; १०४, ९; २. १०, १; २९, ५; ३. ४९, ३; ६. १२, ४; ५२, ६; ७. २९, ४; ५४, २; ९७, २; ८. २१, १४; २२, १५; ४८, ४; १०. २३, ५; २५, ३; ३३, ३; ४९, ४; ६९, १०.

पितुः १. ३१, ११; ६८, ५; ७०, ५; ८७, ५; ११०, ६; ११९, ८; १२७, ८; १४०, ३; १४१, ४; १५५, ३; १५९, २; १६४, १६; २. १३, ४; ३. १, ९; १०; ४८, २; ५३, २; ५४, ९; ४. ४, ११; १७, १२; ५. ४३, ७; ४७, ३; ६. १६, ३५; ४४, २२; ७. १०१, ३; ८. १, ६; ३, २४; ६, १०; ९, २१; १९, २७; ७५, १६; ८६, ४; ९. ७१, २; ७३, ५; ८९, २; ९७, ३०; १०. ३, २; ८, ७; १०, १; ३३, ६; ७; ३९, १.

पितुकृत्ऽतरेभ्यः १०. ७६, ५.

पितुऽभाजः १. १२४, १२.

पितुऽभृतः १०. १, ४; १७२, ३.

पितुं १. ६१, ७; १८७, १; ८. ३२, ८.

पितुऽमत् १. १०१, १.

पितुमतीऽइव ४. १, ८.

पितुऽमती १. ११६, ८.

पितुमन्तःऽइव ५. ४८, ४.

पितुऽमान् १. १४१, २; ३. ५४, २१.

पितुमान्ऽइव १. १४४, ७.

पितुऽयतः १०. १४२, २.

पितुऽसनिः १०. ७१, १०.

पितूनां १. ६९,२; ५. ७, ६.

पितृऽतमः ४. १७, १७.

पितृऽभिः ८. ४८, १३; १०. १४, ४; ८; १५, ९; १०; १७, ८; ६४, १४; १०७, १; १६९, ४.

पितृऽभ्यः १. ११९, ४; २. ५, १; ५. ४७, १; १०. १५, २; १२; १६, १; २; ५; ११; १७, ३; ४०, १०.

पितृऽभ्यां १. १११, १; ३. ७, ६; ४. ३३, २.

पितृऽयज्ञाय १०. १६, १०.

पितृऽयाने १०. २, ७.

पितृऽवत् ८. ४०, १२; १०. ६६, १४.

पितृऽवित्तः १. ७३, १.

पितृऽवित्तस्य १. ७३, ९.

पितृऽश्रवणं १. ९१, २०.

पितृसदे १०. ८५, २१.

पितृऽसदे १. १७७, ७.

पितृणां १. १०९, ३; ४. १७, १७; ६. २१, ८; ४६, १२; ७. ३३, ४; ८. ४१, २; १०. ५७, ३; ७८, ३; ८८, १५.

पितृन् १. ४२, ५; १६४, १०; १०. १४, १०; १५, ३; १६, ११; १२; १५४, ४.

पितो इति १. १८७, २[२]; ३; ४; ५[२]; ६; ७[२]; ११.

पित्रा १. ११७, १७; ६. ९, २.

पित्रे १. ७१, ५; ११४, ६; ३. ३१, १२; ४. ५०,६; ५. २, १; ६. २०, ११; ८. ६९, १५; १०. १३, ५; १२४, ३.

पित्रोः १. ३१, ४; ९; १२४, ५; १४०, ७; १४६, १; १६०, ३; १८५, २; ५; २. १७, ७; ३. ५, ८; २६, ९; ४. ५, १०; ६. ७, ४; ५; ७. ६, ६; ९. ७५, २; १०. ८, ३; ७; ३१, १०; ३२, ३.

पित्र्यं ८. २०, १३; १०. ५६, ६.

पित्र्यऽवती ९. ४६, २.

पित्र्यस्यऽइव ८. ४८, ७.
पित्र्यां ३. ३९, २; ७. ८६, ५.
पित्र्याणि १. ७१, १०; ७. ५६, २३; ७२, २; १०. ८, ८.
पित्र्यात् ८. ३०, ३.
पित्र्यां २. ४२, २.
पित्र्यासः ७. १, ९.
पित्वः १. १५२, ६; ५. ७७, ४; ६. २०, ४; ७. १०४, १०; ८. २५, २०; १०. १५, ३; ११७, २; ४; १४७, ५.
पिनष्टन ७. १०४, १८.
पिनष्टि १०. १३६, ७.
पिनष्टि १. १९१, २.
पिन्व ६. ३९, ५; ७. २४, ६; ९. ७६, ३.
पिन्वत् ९. ६८, ३.
पिन्वत ५. ८३, ६.
पिन्वतः १०. ६५, ८.
पिन्वतं १. ११८, २; १५१, ६; ५. ६२, ३; ७. ८२, ३; ९९, ६; १०. ३९, २.
पिन्वतं १. ३४, ३; ४; ६. ६३, ८.
पिन्वतां १०. ३६, ५.
पिन्वतां ६. ७०, ६.
पिन्वति ९. ७४, ५.
पिन्वते १. ८, ७; ५. ८३, ४; १०. ६३, ३.
पिन्वते १. ५४, ७; १२५, ५; १८१, ८; २. ३४, ८; ४. ५०, ८; ५. ६३, १; ८. १२, ५; ५०, २; ९. ६८, ४.
पिन्वथः १. ११२, ३.
पिन्वथः ५. ६२, २.
पिन्वध्वं ३. ३३, १२.
पिन्वन् ९. ९७, ३३.
पिन्वंत ७. ३४, ३.
पिन्वंति १. ६४, ६; ५. ५४, ८; ७. ५७, १.
पिन्वंति १. ६४, ५.
पिन्वमानः ४. ५८, ७; ९. ९७, १४.
पिन्वमाना ६. ५२, ६; ९. ७५, ४.
पिन्वमानाः ३. १, ७; ३३, ४; ६. ५२, ४; ७. ५०, ४.

पिन्वमाने इति ३. ३३, २.
पिन्वसि १. १२९, ३; ७. ५, ८.
पिन्वसे ९. ६३, २; ६४, ८.
पिन्वस्व ३. ३, ७.
पिन्वानाः ९. ९४, २.
पिन्विरे ८. ४९, २.
पिपर्तन १. १०६, १–६; १५६, ३; १६६, ६; ८. १८, १७.
पिपर्ति १. ४६, ४; १५२, ३; ७. ७०, २.
पिपर्तु २. २७, ७; १०. ३५, ८.
पिपर्तु ६. ७५, १.
पिपर्पि ५. ४, ६.
पिपर्षि १. ३१, ६; ६. १५, ११.
पिपासति ८. ४, ११.
पिपिन्वथुः १. ११२, १२.
पिपिशुः ७. १०३, ६.
पिपिशे ६. ४९, ३.
पिपिशे २. ३३, ९; ५. ५७, ६; ९. ६८, ४.
पिपिश्रे ५. ६०, ४.
पिपिषे १. ३२, ६.
पिपिष्वती १. १६८, ७.
पिपीलः १०. १६, ६.
पिपीळे ४. २२, ८.
पिपीषति १. १५, ९.
पिपीषते ६. ४२, १.
पिपीषवः ७. ५९, ४.
पिपृक्त ३. ५४, २१.
पिपृत १. ११५, ६.
पिपृत १०. ६३, ८.
पिपृतं १. ९३, १२.
पिपृतं ३. २६, ९; ६. ६०, १२; ७. ६०, १२.
पिपृतां १. २२, १३.
पिपृथ १०. ३५, १४.
पिपृथः १०. ६५, १२.
पिपृग्धि १०. १०, ११.
पिपृहि ३. ३१, २०; ७. १६, १०.
पिपेश १. ६८, ५.
पिपेष २. १५, ६; ३. ३४, ६.
पिप्पलं १. १६४, २०; २२; ५. ५४, १२.

पिप्यत २. ३४, ६.
पिप्यतं २. ३९, ६; ५. ७१, २; ७. ९४, २; ९. १९, २.
पिप्यतां ६. ५०, १२.
पिप्यथुः १. ११६, २२; ११९, ६; ६. ६२, ७.
पिप्युः ७. २३, ४.
पिप्युषी २. १३, १; १६, ८; ५. ७३, ८; ८. १४, ३; ९. १६, ७.
पिप्युषीऽइव १. १८६, ५.
पिप्युषी २. ३२, ३; ८. ६, ४३; ७, ३; १३, २५; ५४, ७; ७२, १६; ९५, ५; ९. ६१, १५; ८६, १८.
पिप्युषीः ८. ६, १९; ७, १९; १०. १४३, ६.
पिप्ये ८. १२, १३; ९. ९३, ३; १०७, १२.
पिप्रतः ८. ६, २; ९. १०, ७.
पिप्रति १. ४१, २; ६. ४८, ५; ८. ५०, ८.
पिप्रती इति ४. ५६, ७.
पिप्रतीं ८. १२, ३१.
पिप्रतोः १. ४६, १२.
पिप्रयः २. ६, ८.
पिप्रयत् ७. १७, ४; ८. ३९, ९.
पिप्रयस्व ८. ११, १०.
पिप्रियाणाः ७. ५७, २.
पिप्रिये ३. ५१, ३.
पिप्रीषति ४. ४, ७.
पिप्रीहि ५. ३३, ७; १०. २, १.
पिप्रुं १. १०१, २; १०३, ८; २. १४, ५; ४. १६, १३; ५. २९, ११; ६. १८, ८; ८. ३२, २.
पिप्रोः १. ५१, ५; ६. २०, ७; १०. ९९, ११; १३८, ३.
पिबं १. १४, १०; १५, १; ३–५; १३०, २; १६४, ४०; १७७, ४; २. १६, ४; ३६, १; ४; ३७, १–३; ३. ३२, १–३; ५; ३५, १०; ३६, २; ३; ४०, २; ४३, ७; ४७, १; ४; ५०, २; ५१, १०; ५. ५१, ५; ६. १७, १; २३, ७; ४०, १; ४३, १; ७. २२, १;

२९, १; ९०, १; ८. १, २६; २, १; ३, १; ४, ३; ८; १०; १२; १७, १; ४; ११; ३२, १९; २०; ३६, १; ३७, १; ६४, १०; १२; ६५, ५; ७६, ७; ९; ८२, २; ७; ९५, २; ३; ९. ८५, २; १०. ९६, १२; १०४, १; २; ११२, १; ६; ११६, १[४]; ७; १७९, ३.

पिब १. ४, २; १०, ११; १६, ५–७; २३, १; ८४,४; १०४, ९; २. ३६, ५; ३. ३५, ९; ४२, ७; ४७, २; ४८, १; ५२, ७; ४. ४६, १; ५. ४०, १; ६०, ८; ६. ४०, २; ४१, ३; ४७, ६; ८. ६, ३६; २१, ३; २६, २०; ३२, २१; ४५, २४; ४९, ४; ६५, ८; ९१, २; १०१, १०; १०. २४, १; ११६,२.

पिबत् ८. २, २३; १०. ३७, ११.

पिबत् ५. २९, ७.

पिबत १. १५, २; ४. ३४, ४.

पिबत १. १६१, ८[२]; २. ३६, २; ४१, १४; ५. ५१, २; ७. ३८, ८; ५९, ३.

पिबतः ८. १०, ४.

पिबतं १. १५, ११; १३५, ४; २. ४१, ३; ४. ४६, ६; ४९, ६; ६. ६०, ७; १५; ६९, ७; ७. ६६, १८; ८. ५, ११; ८, १; २२, ८; ३५, १०; ५७, ४; ८७, २; ४.

पिबतं १. ३४, १०; ४६, १५; ४७, १; १०८, १; ५–१२; १३५, ५; २. ३६, ६; ३७, ५; ३. ५८, ७; ४. ४५, ३; ५०, १०; ६. ६८, १०; ७. ७४, ३; ८. ५, १४; १९; ३५, १.

पिबति ५. ३७, ४.

पिबतु १. ४४, १४.

पिबतु २. ३७, ४; ३. ५०, १; ५१, ९; ५. ३६, १; ९. ११३, १; १०. १७०, १.

पिबध्यै १. ८८, ४; ३. ३२, १५; ४. २७, ५[२]; ६. ४४, १४; ७. ९२, २; ८. ५७, ३; ५८, ३; ९. ९७, २०.

पिबध्वं ३. ५२, १०; ४. ३५, ९; ७. ३७, २.

पिबन् ४. २३, १.

पिबतः ५. ६१, ११.

पिबतं ८. ३३, ७.

पिबति १. २३, १८; ८. ९४, ४; ५; ९. ६४, २४; १०९, १५.

पिबति १. ८४, १०; ४. २५, ३.

पिबती: ६. २८, ७.

पिबतु ७. ५१, २.

पिबतु १. १४, ८; १०. ८७, १८; १६९, १.

पिबतौ १. १८०, १.

पिबऽपिब २. ११, ११.

पिबसि ६. ४१, २; १०. २८, ३.

पिबस्व ४. ३५, ७.

पिबात् ९. १०८, १४.

पिबातः ५. ७७, १.

पिबाति ८. २४, १३.

पिबाथः ४. ४४, ४; ६. ६३, २; ७. ६७, ४; ८. ८, ३.

पिबाथः ७. ६९, ३; ८. ५७, १.

पिबामि १०. ८६, १९.

पिबाव १०. ८३, ७.

पिबासि ३. ३५, १.

पिब्दुना ६. ४६, ६; ९. १५, ६.

पियानः १. ७९, ३.

पियारुं १. १९०, ५; ३. ३०, ८.

पिशंग ७. ५५, २.

पिशंगऽअश्वाः ५. ५७, ४.

पिशंगऽभृष्टिं १. १३३, ५.

पिशंगं ४. ५३, २; ९. २१, ५; ७२, ८; १०७, २१.

पिशंगऽराते ५. २१, २.

पिशंगऽरूपः १. १८१, ५; २. ३, ९.

पिशंगऽरूपं ८. ३३, ३.

पिशंगऽसंदृशं २. ४१, ९.

पिशंगा १०. १३६, २.

पिशंगैः १. ८८, २.

पिशा ७. १८, २.

पिशाःऽइव १. ६४, ८.

पिशाचिं १. १३३, ५.

पिशानाः ७. ५७, ३.

पिशुनेभ्यः ७. १०४, २०.

पिष्टं ५. ५६, १.

पिस्पृशः ६. १५, १८.

पिस्पृशति ६. ४९, १२.

पीतः ६. ४७, ३; ८. ४८, ४; १०; १२; ९६, २१; ९. ४५, ६; ८६, ४१.

पीतं १. १७९, ५.

पीतयः ४. ३४, ५.

पीतये १. ५, ६; १६, ३; २२, १; २३, २; ४७, ९; ५५, २; १३७, २[२]; ३; १६६, ७; ३. ४२, ४; ८; ९; ४. ३६, २; ४८, १; ४९, २; ५. ५१, १; ७५, ६; ६. ४०, २; ६८, १०; ७. ३२, ४; ५९, ५; ८. १, २५; १२, १२; १७, १५; ३२, २४; ३३, १३; ३४, १०; ३५, २३; ४५, २२; ६५, ३; ६८, ७; ८५, १; ९२, ५; ९७, ८; ११; ९. १२, २; १७, ८; २५, १; ३०, ५; ३२, २; ३७, १; ३८, २; ६; ४३, २; ४५, १; ५०, ५; ६२, ८; ६४, १२; ६५, ८; १४; ७४, ९; ७८, ४; १०. ९, ४; २९, ६; १०४, ६.

पीताः ४. ३७, २; ६. १७, ४; ८. ४८, ५; ९. १०८, २; १०. ११९, २.

पीतासः १. १६८, ३; ८. २, १२.

पीतिः ४. ३५, २; ५. ७६, ३.

पीतिं १. १३४, ६[२]; २. ११, १७; १४, १; २; ४. ३३, ११; ३४, १; ४७, २; ५. ५१, ६; ७. ९८, २; ८. ८२, ६; ९. १८, ३; १०. १००, २; १०४, ३.

पीतौ ६. २७, १; २.

पीत्या १. ४६, १३.

पीत्वा १. ४, ८; ८. ६९, ७; ९२, ६; ९. २३, ७; १०८, २; १०. ४४, ८; ९६, ९.

पीत्वी ३. ४०, ७; ८. ७६, १०; १०. ५५, ८; ११३, १.

पीपय ३. १५, ६.

पीपयः १. ६३, ८.

पीपयंत् ३. ५७, ६; ९. ६, ७; १०. १३३, ७.
पीपयत् १. ७७, ५; ८. १, १९.
पीपयत १०. ६४, १२.
पीपयतः २. २७, १५.
पीपयन् ७. ६५, २.
पीपयन् १. १५२, ६.
पीपयंत १. ७३, ६; १८१, ५; ६.
पीपयंत १. १५३, ४; १६९, ४; ५. ३४, ९.
पीपरः १. १३८, २; ४. २, ८.
पीपरत् १. ४६, ६.
पीपरंत ३. ३२, १४.
पीपरत् २. २०, ४; ५. ७७, ४.
पीपार्य १. १५३, ३; ६. १०, ३; ६६, १; ७. २७, ४.
पीपाय १. १८१, ८; २. २, ९; ३५, ७; ४. ३, ९; ६. ४४, २१; ८. २९, ६.
पीपिऽवांसं ५. ७६, १; ७. ९६, ६.
पीपिहि ६. १७, ३; ३५, ४.
पीपेथ ८. ५०, ६.
पीपेरिति पीपेः ४. १६, २१.
पीप्याना १०. १०२, ११.
पीप्यानाऽइव ३. ३३, १०.
पीप्यानाः ३. १, १०; ७. ३६, ६.
पीयंतः १०. ६८, ६.
पीयति १. १४७, २.
पीयत्नवे ८. २, १५.
पीयंति ८. २१, १४.
पीयुषं २. १३, १.
पीयूषः ९. १०९, ३; ६.
पीयूषं २. ३५, ५; ३. ४८, २; ६. ४७, ४; ९. ५१, २; ८५, ९; ११०, ८; १०. ६३, ३; ८७, १७; ९४, ८.
पीयोः १. १७४, ८; २. १९, ७.
पीवः १. १८७, ८; ९; १०^{२}; १०. ८६, १४; १००, १०.
पीवःऽअन्नान् ७. ९१, ३.
पीवःऽअश्वाः ४. ३७, ४.
पीवरीः ८. ५, २०; २२, ९.
पीवसा १०. १६, ७.
पीवसा १. १५२, १.
पीवस्वतीः १०. १६९, १.
पीवानं १०. २७, १७.
पुंसः १. १२४, ७; १६२, २२; १६४, १६; ५. ६१, ६; ७. ६, १; १०. ३२, ३.
पुंडरीकानि १०. १४२, ८.
पुण्यऽगंधाः ७. ५५, ८.
पुण्यं २. ४३, २.
पुत्र १. ४०, २; ३. १४, ४; ६; १६, ५; १८, ४; ४. १८, ११; ५. ३, १; ६; ४, ६; ८. ७७, २; ९२, १४; १०. ३३, ७.
पुत्रः १. ३१, ११; ३२, ९; ६९, १; ३; ८९, १०; १५५, ३; १६०, ३; १६४, १६; १८१, ४; २. १, ९; ७, ६; ३. २, २; १४, १; २९, ३; ५३, २; ५८, १; ४. १८, ७; ४२, ४; ५. ३, ९; ९, ४; २५, १; ४३, ७; ६. ९, २; १६, १४; ७५, ५; ७. ३२, ३; १०१, ३; १०३, ३; ८. ८, ४; ८; १९, २७; २७, २२; ९. ७५, २; ९७, ३०; १०१, १४; १०. १, ७; ३१, १०; ३२, ३; ८५, १४; १४०, २; १४४, ४.
पुत्रकाः ८. ६९, ८.
पुत्रऽकाम १०. १८३, १.
पुत्रऽकामे १०. १८३, २.
पुत्रऽकृथे ५. ६१, ३.
पुत्रऽकृथेषु १०. ६३, १५.
पुत्रं १. ३८, १; ९६, ३; ११७, २४; १२५, ३; ३. ५७, ३; ४. १९, ९; ३०, १६; ५. ११, ६; २५, ५; ६. ७५, ४; ७. ४१, २; ८. ४, ६; १०१, ६; १०. १८, ११; ३१, ११; ६५, १२; ६९, १०; १०१, १२.
पुत्रंऽइव १०. २२, ३; ११९, ४; १३१, ५.
पुत्रस्य १. १५९, ३; ८. ४५, ३६; ९०, २; १०. ३४, १०.
पुत्रा १०. १०६, ४.
पुत्राः १. ६८, ५; १६४, ११; ३. ५३, २४; ४. २, १५; ५. ५८, ५; ६. ६६, ३; ६७, ९; ७. २६, २; ६०, ५; १०. १३, १; ११५, ९; १५९, ३.
पुत्राः २. २८, ३.
पुत्रान् १. १६२, २२; ३. ३१, ३; ७. ५४, २; १०. ५५, १; ८५, ४१; ४५; १८३, ३.
पुत्राय ५. ४७, ६; ७. १०२, १; १०. ३७, १.
पुत्रायऽइव १०. ३९, ६.
पुत्रासः १. ८९, ९; १३०, १; ३. ५३, ७; ७. ४३, ३; ८. १८, ५; १०. १०, २; १३, ५; ७२, ८; ७७, २; १८५, ३.
पुत्रिणं ५. ४, ११.
पुत्रिणा ८. ३१, ८.
पुत्रिऽयंतः ७. ९६, ४.
पुत्रे २. २९, ५.
पुत्रेभ्यः १. १६१, १०; ७. ३२, २६; १०. १५, ७.
पुत्रैः १. ७२, ९; २. २६, ३; १०. ७२, ९; ८५, ४२.
पुनः १. ६, ४; २४, १; २; २५, १७; ९४, १२; ११७, १३; १२३, १२; १२४, ४; १४०, ७; १४७, ४; १८९, ३; २. २४, ६; ७; ४. २४, ९; १०; ३३, ३; ३६, ३; ५. ३०, ११; ४६, १; ५१, १५; ७४, ५; ८०, ६; ६. ५४, १०; ७. ४, ८; ५८, ५; ७६, ३; १०४, ३; ८. ४३, ७; १०१, ४; १०. १, ४; १४, ८; १२; १६, ५; १९, २^{२}; ३; ६; २४, ५; ६; २८, १; ३९, ४; ५७, ५; ५९, ६; ७^{४}; ७२, ९; ८६, २१^{२}; ९५, २; १०८, ९; १०९, ६^{३}; १११, ७; १६१, ४; ५; १८२, १.
पुनःऽदाय १०. १०९, ७.
पुनःऽनव १०. १६१, ५.
पुनःऽपुनः १. ९२, १०; ३. ५, ७.

पुनःऽभुवंः ९. ७२, ६.
पुनःऽभुवा १. ६२, ८.
पुनःऽभूः १. १२३, २.
पुनःऽमन्यौ १. ११७, १४.
पुनःऽसर ७. ५५, ३.
पुनःऽहनंः १०. ३४, ७.
पुनती ४. ५, ७.
पुनते ८. ५३, ६; ९. ७०, ३.
पुनंतः १०. ७१, २.
पुनंता १०. २७, १७.
पुनंति ३. ८, ५; ९. १०९, ११.
पुनंति ३. ३६, ७; ९. ७३, ७; ९८, ७; ९९, ५.
पुनंतु ९. ६७, २७².
पुनंतु १०. १७, १०.
पुनरिति १. २०, ४; ६; ३१, ४; ११०, १; ८; ११८, ६; १४०, २; ८; २. ३८, ४; ३. ५८, ६; ८. १, १२; २०, २६; ४३, ९; ७२, १; १०. १६, १३; ३९, ८; ५६, ४; ५७, ४; ५९, ६; ७; ६१, ५; ८५, ५; १८; ३१; ३८; ३९; ९०, ४; १०९, २; १२८, ६; १३५, २; १३७, १²; १४३, १; ३.
पुनर्वसू इति पुनःऽवसू १०. १९, १.
पुनाते ९. १०४, ३.
पुनाति १. १६०, ३; ९. १, ६.
पुनातु ९. ६७, २२.
पुनान ९. ९, ७.
पुनानः ३. १, ५; ७. ९, २; ९. ६, ९; ८, ३; ६; १३, १; १६, ६; ८; १८, ७; १९, १; ३; ५; २०, ५; २५, ४; २७, १; ६; २८, ६; ३०, १; ४०, १; ५; ६; ४२, ५; ४३, ३; ५४, ३; ४; ५७, ४; ६१, ६; २३; २७; ६२, २३; ६३, २८; ६४, १४; १५; २५–२७; ६६, २८; ६८, ९²; ७०, ८; ७५, ५; ८२, १; ८६, ३; ९; २१; २६; ३३; ८७, १; ९; ९१, ४; ६; ९२, ३; ६; ९३, ५; ९५, १; ५; ९६, ३; १५; २३; ९७, ६; १२; १८; २५; २७; ३७; ३८; ४५; ४७; ९९, ६; १००, २; १०१, ७; १०३, २; ४; ५; १०६, १०; १२; १०७, २; ४; ६; १८; १०९, ९; ११०, १०; ११; १११, १²; ११३, ५.
पुनानं ९. ३५, ५; ८६, २५; ९९, ४; १०५, १.
पुनानस्य ९. १६, ४; ३५, ६; ८६, ४७.
पुनानाः २. ३, ५; ३. ३१, १६; ६. ६६, ४; ७. ४९, १; ९. ६, ४; २४, २; ८९, ५; १०६, ९.
पुनानाय ९. २९, ३; १०३, १; १०४, १.
पुनानासः ६. ३७, २; ९. ८, २.
पुनाने इति ४. ५६, ६.
पुनामि १. १३३, १; १०. १३, ३.
पुनीत ९. ६७, २७.
पुनीतन ९. ४, ४.
पुनीतन १. १५, २; ९. ११, ५; ६२, २९.
पुनीतात् १०. ३०, ५.
पुनीते ८. १२, ११; १३, १.
पुनीषे ७. ८५, १.
पुनीहि ९. १६, ३; ५१, १; ६७, २७.
पुनीहि ९. ६७, २३; २४²; २५; २६.
पुपुष्याः १०. १०४, ९.
पुपुष्वान् १०. ७१, ११.
पुपूतनि १०. १३२, ६.
पुपूर्याः ५. ६, ९.
पुपोर्ष ३. ५५, १९.
पुपोष १. १७९, ६; १०. १७०, १.
पुमः ९. ९, ७.
पुमांसं ३. २९, १३; ६. ७५, १४; ७. १०४, २४.
पुमान् ४. ३, १०; ५. ६१, ८; ६. ७५, १४; १०. १३०, २².
पुरएताऽइव ६. ४७, ७.
पुरः १. ३३, १३; ५१, ५; ११; ५३, ८; ५४, ६; ६३, २; ७; १०३, ३; ८; १३०, ७; १३१, ४; १७४, २; ८; २. १४, ६; १९, ६; २०, ८; ३. १२, ६; १५, ४; ४. १६, १३; २६, ३; २७, १; ३०, १३; ३२, १०; ५. ४१, १२; ६. १६, ३९; १८, ५; २०, ७; १०; ३१, ४; ३२, ३; ७३, २; ७. ५, ३; १८, १३; १९, ५; २१, ४; २६, ३; ९९, ५; ८. १, ८; ३३, ७; ९३, २; ९७, १४; ९. ४८, २; ६१, २; १०. ८९, ७; ९९, ७; ११; १०१, ८.
पुरः १. ४१, ३; ४२, १; ५४, ३; १०२, ९; १२९, ९; १३१, १; १३९, १; १६२, ३; १६३, १२; १७०, ४; २. ३२, १; ४१, ११; ३. २, ५; ५३, २३; ४. ७, ९; १५, ४; २०, ३; ५०, १; ५. २, १; १६, १; २८, २; २९, ५; ३१, ११; ८२, ८; ८६, ५; ६. १०, १²; १५, ७; १७, ८; २५, ७; ७५, ६; ७. १, ३; ५३, १; ६२, २; ८. १२, २२; २५; १७, ९; १५; ४१, ७; ४४, ३; ४५, ९; ६१, १५; १६; १०. १७, ५; २०, ५; ९०, ५; १०३, ८; १४२, २; १५२, २; १७१, ४; १८९, १.
पुरःऽएता १. ७६, २; ३. ११, ५; ५. ४६, १; ६. २१, १२; ७. ३३, ६; ४१, ५; ९. ८७, ३; ९७, २९.
पुरःऽगवः १०. ८५, ८.
पुरःऽगवी १०. १३७, ७.
पुरःऽगाः १. १८८, ११; १०. ११०, ११; १२४, १.
पुरःऽजिती ९. १०१, १.
पुरःऽप्रस्रवणाः ८. १००, ९.
पुरःऽभूः ३. ३१, ८.
पुरःऽयावानं ५. ३५, ७; ८. ८४, ८; ९. ५, ९.
पुरःऽयुधा १. १३२, ६.
पुरःऽयोधः ७. ३१, ६.
पुरःऽयोधा ७. ८२, ९.

पुरःऽरथं १०. ३९, ११; १३३, १.
पुरःऽरुचं ९. ९८, १२.
पुरःऽसदः १. ७३, ३.
पुरःऽस्थाता ८. ४६, १३.
पुरःऽहा ६. ३२, ३.
पुरःऽहितः १. ४४, १०; १२; ५५, ३; ५८, ३; ९४, ६; १२८, ४; २. २४, ९; ३. २, ८; ३, २; ११, १; ८. २७, १; १०१, १२; ९. ६६, २०; १०. १, ६; ९८, ७; १५०, ४; ५^{2}.
पुरःऽहितं १. १, १; ५. ११, २; १०. ९२, २.
पुरःऽहिता १०. ६६, १३.
पुरःऽहितिः ७. ६०, १२; ८३, ४.
पुरःऽहितौ १०. ७०, ७.
पुरं १. ५३, ७; १४९, ३; ५. १९, २; ८. १, २८; ६, २३; ३२, ५; ६९, ८; ७३, १८; १००, ८; १०. ६७, ५; ८७, २२.
पुरंऽदर १. १०२, ७; ८. १, ७.
पुरंऽदरः २. २०, ७; ३. ५४, १५; ५. ३०, ११; ८. १, ८; ६१, १०.
पुरंऽदरं ६. १६, १४; ८. ६१, ८.
पुरंऽदरस्य ७. ६, २.
पुरंऽदरा १. १०९, ८.
पुरंऽधये १०. ३९, ७.
पुरंऽधिः १. १६६, १३; ११७, १९; १८१, ९; २. ३१, ४; ३. ६१, १; ४. २६, ७; २७, २; ३४, २; ५. ४२, ५; ६. ४९, १४; ७. ३५, २; ९. ९३, ४; १०. ८५, ३६.
पुरंऽधिं १. ११६, ७; १३४, ३; १८०, ६; २. ३८, १०; ४. २७, ३; ६. २१, ९; ७. ९, ६; ३६, ८; ३९, ४; ९. ९७, ३६; १०. ६४, ७; ८०, १; ११२, ५.
पुरंधिऽवान् ९. ७२, ४.
पुरंध्री इति पुरंऽधी ९. ९०, ४.
पुरंऽधीः १. १२३, ६; १५८, २; ४. २२, १०; ५०, ११; ५. ४१, ६; ७. ६७, ५; १०. ३९, २.
पुरंऽध्या २. १, ३; ३. ६२, ११; ५. ३५, ८; ७. ३२, २०; ८. ६९, १; ९२, १५; ९. ११०, ३; १०. ६५, १३; १४.
पुरंऽध्यां १. ५, ३.
पुरंयस्य ६. ६३, ९.
पुरस्तात् १. १२३, १०; १२४, ३; ११; १९१, ८; ३. ८, २; ९; २७, ७; २९, ५; ४. ५१, १; २; ८; ५. ८०, ४; ८३, ८; ६. १९, ९; ७. ६७, २; ७२, ५; ७६, २; ७८, ३; ८. १, ३४; २८, ३; ४८, १५; ५७, २; ८०, ४; १००, १; १०. १७, ४; ३६, १४; ४२, ११; ८७, २०; २१; १३५, ६; १३९, १.
पुरा १. २४, ४; ३९, ७; ५३, ७; ७१, १०; ९६, ७; १०३, १; १०५, ७; ११२, १६; ११३, १३; १२१, १०; १२९, ५; १३९, ८; १६७, १०; १६९, ५; २. १६, ८; २०, ४; २८, ५; ८; ३०, ४; ३. ३०, १०; ३२, १४; ४. ३, १; २८, ३; ५१, ७; ५. ५३, १; ७७, १; ६. २२, ४; २७, १; ३४, १; ४५, ११; ४८, १९; ६०, ४; ६५, ४; ७. ५६, २३; ८८, ५; ९१, १; ८. १, १२; ७, २१; ८, ६; २१, ७; ९; २४, १५; ४४, ३०^{2}; ४६, १०; ६६, ५; ६७, ५; १६; २०; ७५, १६; ७८, ६; ८०, २; ९. ७०, ९; ९९, ३; १०. १०, ४; ३९, ६; ५४, २; ७६, ३; ८६, १०, ९७, १; ११; ११७, २.
पुराऽजा ७. ७३, १.
पुराऽजाः १. ११८, ३; ६. २१, ५; ७. ९७, ५; १०. ५, ५.
पुराऽजां ३. ३१, १९; ६. ३८, ३.
पुराणः ४. १८, १; १०. ४३, ५.
पुराणं ३. ५४, ९; ५८, ६.
पुराणऽवत् ८. ४०, ६; ७३, ११; १०. ४३, ९.
पुराणा १०. ३९, ५.
पुराणान् १०. १३५, १; २.
पुराणी १. ९२, १०; ३. ६१, १; ४. ५१, ६.
पुराणे १०. १३०, ६.
पुराण्या ९. ९९, ४.
पुराण्योः ३. ५५, २.
पुरां १. १३०, १०.
पुरां १. ११, ४; ६१, ५; ३. ४५, २; ४. ३०, २०; ६. १८, ८; २०, ३; ८. १७, १४; ९८, ६; १०. ४६, ५.
पुराषाट् १०. ७४, ६.
पुरि ९. १०७, १०.
पुरिऽइव ६. २, ७.
पुरीषं ५. ४५, ६; १०. २७, २३.
पुरीषा १०. १०६, ५.
पुरीषाणि ६. ४९, ६.
पुरीषात् १. १६३, १; ४. २१, ३; १०. २७, २१.
पुरीषिः ५. ५५, ५.
पुरीषिणं १. १६४, १२; १०. ४८, ४.
पुरीषिणा १०. ६५, ९.
पुरीषिणी ५. ५३, ९.
पुरीष्यासः ३. २२, ४.
पुरु १. ६२, १०; ८१, ७; ११७, ९; १२७, ३; १३९, १०; १४२, १०^{2}; १४४, ४; १५०, १; १६६, ३; १३; १९१, ९; २. १६, ३; ३. ३१, १५; ५१, ५; ५८, ५; ४. २०, ९; २८, ३; ३१, ८; ३७, ८; ५५, ९; ५. २, ४; ३, ४; ९, ४; २३, ३; ३३, ४; ३४, ७; ३७, ३; ७३, १; २; ७४, ८; ६. १६, ५; १८, १३; २९, ६; ४४, १४; ६२, २; ६३, ८; ७. ६२, १; ८१, ३; ९७, ७; ८. १, २२; २, ३२; ४, १; १६, ७; २३, २७; २५, १६; ३९, ७; ४१, ५; ६०, १४; ६१, ८; ८३, ३; ९२, ९; ९. १५, २; ६२, २; १०. १०, १; २३, ५; २८, ६; ४८, ४; ६१, १३; ६४, १४; ७३, २; ९४, ५.
पुरुऽअनीक १. ७, ५; ६. ५, २; १०, २; ११, ६; ७. ४२, ३.
पुरुऽतरुणा ५. ७०, १.
पुरुऽकुत्सं १. ११२, ७.

पुरुऽकुत्सानी ४. ४२, ९.
पुरुऽकुत्साय १. ६३, ७; १७४, २; ६. २०, १०.
पुरुऽकृत् ८. ६१, ६.
पुरुकृत् १. ५३, ३; २. १३, ८; ६. २१, ५; ९. ९१, ५; १०. १७९, ३.
पुरुऽकृत्वा ६. ३२, ३.
पुरुऽक्षुः १. ६८, ५; ६. १९, ५; १०. ७, ४; ७४, ५; १२८, ८.
पुरुऽक्षुं २. ४०, ४; ४. ३४, १०; ६. ६८, ६; ७. ५, ९; ८४, ४; ८. ५, १५; ७, १३.
पुरुक्षो इति पुरुऽक्षो ३. २५, २; ९. ९१, ५.
पुरुऽक्षोः ३. ५४, २१; ४. २९, ५; ६. २२, ३; ५०, ११.
पुरुऽगूर्तः ६. ३४, २.
पुरुऽचंद्रः १. २७, ११; ३. २५, ३.
पुरुऽचंद्रं ५. ८, १; ९. ६२, १२.
पुरुऽचंद्रस्य २. २, १२; ६. ३६, ४; ७. १००, २; ९. ८९, ७.
पुरुऽचंद्रा ८. ५, ३२.
पुरुऽचंद्राः ५. ६१, १६.
पुरुऽचंद्रेण ७. ७२, १.
पुरुऽचंद्रैः १. ५३, ५.
पुरुऽचेतनः ६. १६, १९.
पुरुऽजातः ७. ३५, २.
पुरुऽतमः ३. ६२, २; ६. ६, २.
पुरुऽतमं १. ५, २; ४. ४४, १; ५१, १; ५. ५६, ५; ६. ४५, २९; ८. १०२, ७; १०. २३, ६; ७४, ६.
पुरुऽतमस्य ३. ३९, ७; ६. २१, १.
पुरुऽतमा १. १२४, ६; ७. ७३, १.
पुरुऽतमानि ६. ३२, १.
पुरुऽतमासः ८. ६६, ११.
पुरुऽत्मानं ८. २, ३८.
पुरुऽत्रा ८. ८, २२.
पुरुऽत्रा १. ३२, ७; ७०, ५; १४६, ५; १६३, ११; २. १८, ७; ३९, १; ३. ५५, ३; ४; ६१, ७; ४. ३२, २१; ६. ४७, २९; ७. १, ९; १६; ६९, ६; १०३, ६; ८. १, ७; ५, १६; ११, ८; ३३, ८; १०. २२, ९; २५, ६; ४५, २; ७१, ३; ८०, ४; १०६, ३; १२५, ३; १२७, १.
पुरुऽदंसं ३. १, २३.
पुरुऽदंससा १. ३, २.
पुरुऽदंससा ८. ८७, ६.
पुरुऽदंससा ६. ६३, १०; ८. ९, ५.
पुरुऽदंसा ७. ७३, १.
पुरुऽदत्र ६. १८, ९.
पुरुऽदस्मं ३. ५४, १४.
पुरुऽदिनेषु १०. २९, १.
पुरुऽद्रप्साः ५. ५७, ५.
पुरुऽद्रुहः ३. १८, १.
पुरुध ३. ५४, १९; ५६, ३; १०. ५६, ५; ५९, २.
पुरुधऽप्रतीकः ३. ७, ३; ४८, ३.
पुरुधा १. १२२, २; ३. ५०, ३; ५५, १९; ४. २, १९; ६. १, १३; १०. २७, २१; ५५, ३; ११२, ७; १७०, १.
पुरुऽनामन् ८. ९३, १७.
पुरुनिःऽसिधे १. १०, ५.
पुरुनिःऽसिध्वानं ४. ३८, २.
पुरुनिःऽस्थः ५. १, ६.
पुरुनिःऽस्थाः ८. २, ९.
पुरुऽनीथा ७. ९, ६.
पुरुऽनीथे १. ५९, ७.
पुरुऽनृम्णाय ८. ४५, २१.
पुरुऽपंथाः ६. ६३, १०.
पुरुऽपुत्रां १०. ७४, ४.
पुरुऽपेशसं ३. ३, ६.
पुरुऽपेशासु २. १०, ३.
पुरुऽप्रजातस्य १०. ६१, १३.
पुरुऽप्रशस्तः १. ७३, २; ६. ३४, २; ८. १०३, १२.
पुरुऽप्रशस्तं ८. १२, १४; ७१, १०.
पुरुऽप्रशस्ता १०. ६६, ७.
पुरुऽप्रिय १. ४५, ६.
पुरुऽप्रियः ३. ३, ४; ५. १८, १.
पुरुऽप्रियं १. १२, २; ४४, ३; ८. ३१, १४; ४३, ३१; ७४, १.
पुरुऽप्रिया ८. ५, ४; १२, १०.
पुरुऽप्रिये ८. १८, ४.
पुरुऽप्रैषः १. १४५, ३.
पुरुऽप्रैषाः १. १६८, ५.
पुरुऽभुजा १. ३, १.
पुरुऽभुजा १. ११६, १३; १४; ५. ४९, १; ७३, १; ६. ६३, ५; ८; ८. ८, १७; १०, ६; ८६, ३.
पुरुभू इति पुरुऽभू ४. ४४, ४.
पुरुऽभूतमा ५. ७३, २; ८. २२, १२.
पुरुऽभूषु ९. ९४, ३.
पुरुऽभोजः ७. ७५, ८.
पुरुऽभोजसः ८. ४९, २.
पुरुऽभोजसं ३. ३४, ९; ७. ९, २; ८. ८८, २.
पुरुऽभोजसा ८. २२, १६.
पुरुमंतु इति पुरुऽमंतु १. १५८, १.
पुरुऽमंद्रा ८. ५, ४; ८, १२.
पुरुऽमायः ३. ५१, ४; ६. २२, १.
पुरुऽमायं १. ११९, १.
पुरुऽमायस्य ६. १८, १२; २१, २.
पुरुऽमाय्यं ८. ६८, १०.
पुरुऽमित्रस्य १. ११७, २०; १०. ३९, ७.
पुरुऽमीळ्ह ८. ७१, १४.
पुरुऽमीळ्हः १. १८३, ५.
पुरुऽमीळ्हस्य १. १५१, २.
पुरुऽमीळ्हाय ५. ६१, ९.
पुरुऽमेधः ९. ९७, ५२.
पुरुऽरथः १०. ६४, ५.
पुरुऽरुचः १०. १०४, ५.
पुरुऽरूपः २. ३३, ९; ५. ८, ५; ६. ४७, १८.
पुरुऽरूपं २. २, ९; ५. ८, २; ८. १, ४; ६०, १८.
पुरुऽरूपा ३. ५५, १४.
पुरुऽरूपाः ६. २८, १.
पुरुऽवर्पसं १०. १२०, ६.
पुरुऽवसुः २. १, ५; ५. ३६, ३; ४२, ७; ७. ३२, २४; ३८, १; ८. १, १२; ३२, ११; ४६, १३; ४९, १; ५२, ५.
पुरुऽवसुं १. ८१, ८; ८. ४, १५; ४६, ७; ७१, १०.

पुरुवसू इति पुरुऽवसू **१.** ४७, १०; **८.** ५, ४; ८, १२.
पुरुवसो इति पुरुऽवसो **६.** २२, ४; **८.** ३, ३; ४६, १; ६१, ३; १०३, ५; **१०.** २४, १.
पुरुऽवाजाभिः **६.** १०, ५.
पुरुऽवार **२.** २, २; **४.** २, २०; **६.** १, १३.
पुरुऽवारः **४.** ५, १५; २१, ५; **६.** ५, १; **९.** ९३, २; ९६, २४.
पुरुवारऽपुष्टिः **१.** ९६, ४.
पुरुऽवारं **१.** ११९, १०; **२.** ४०, ४; **६.** १५, ७.
पुरुऽवारस्य **४.** ३९, २.
पुरुऽवारेभिः **१.** १३९, १०.
पुरुऽवीरं **४.** ४४, ६; **६.** ६, ७; ४९, १५; **८.** ७१, ६.
पुरुऽवीरस्य **२.** २८, ३; **६.** २२, ३.
पुरुऽवीराः **२.** २७, ७.
पुरुऽवीराभिः **६.** ३२, ४.
पुरुऽवीरां **१०.** १६७, १.
पुरुऽवेपसं **८.** ४४, २६.
पुरुऽव्रतः **९.** ३, १०.
पुरुऽशाक **६.** २१, १०; २४, ४; **७.** १९, ६.
पुरुशाकऽतमा **६.** ६२, ५.
पुरुऽशाकाय **३.** ३५, ७.
पुरुष **१०.** ९७, ४; ८.
पुरुषऽअदः **१०.** २७, २२.
पुरुषः **१०.** ९०, १–५; ९७, १७.
पुरुषऽघ्नं **१.** ११४, १०.
पुरुषता **७.** ५७, ४; ७५, ८.
पुरुषऽत्रा **३.** ३३, ८; **४.** १२, ४.
पुरुषत्वता **४.** ५४, ३; **५.** ४८, ५.
पुरुषं **१०.** ५१, ८; ९०, ७; ११; १५; ९७, ५.
पुरुषस्य **७.** १०४, १५.
पुरुषीणां **७.** १०२, २.
पुरुषेण **१०.** ९०, ६.
पुरुषेभ्यः **१०.** १६५, ३.
पुरुष्याः **७.** २९, ४.
पुरुऽसंतिं **१.** ११२, २३.
पुरुऽसंत्योः **९.** ५८, ३.
पुरुऽसंभृतं **८.** ६६, ४; १००, ६.
पुरुऽस्तुत **४.** २१, १०; **८.** ९३, १७.
पुरुऽस्तुत **१.** ५७, ४; १०२, ३; **३.** ४०, २; ४५, ५; ५२, ६; ६०, ६; **५.** ८, ५; **६.** ५६, ४; **८.** ६, ४५; १३, २५; १५, ३; ११; ६२, ७; ६६, ५; ७६, ७; **१०.** ३२, २; ३८, ३.
पुरुऽस्तुतः **१.** ११, ४; १४१, ६; **८.** ३३, ६; ४६, १२; **९.** ७७, ४.
पुरुऽस्तुतं **८.** १३, २४; १५, १; ९२, २.
पुरुऽस्तुतस्य **३.** ३७, ४; **९.** ७२, १.
पुरुऽस्तुता **५.** ८०, ३.
पुरुऽस्तुताय **५.** ३४, १.
पुरुऽस्पृक् **१०.** ५५, २.
पुरुऽस्पृहः **१.** १४२, ६; **४.** ८, ७; ४७, ४; **८.** २३, २७; **९.** ९८, ५; **१०.** ४६, १०.
पुरुऽस्पृहः **८.** २०, २.
पुरुऽस्पृहं **१.** ४७, ६; **२.** ७, १; **५.** ७, ६; **८.** २२, २; ६०, ११; **९.** १४, १; ३०, ३; ६२, १२; ६५, २८; ९८, १; १०२, ६; १०७, २१.
पुरुऽस्पृहा **८.** ८, २२; ४६, ५.
पुरुऽहन्मन् **८.** ७०, २.
पुरुऽहूत **६.** २२, ४; **९.** ५२, ४; ६४, २७.
पुरुऽहूत **१.** ३०, १०; ४४, ७; ६३, २; १०४, ७; १२१, ९; १७४, ३; **२.** ३२, ३; **३.** ३०, ५; ७; ८; ३२, १६; ५१, ८; ५४, १७; **४.** १६, ८; २०, ७; **५.** ३१, ४; ३६, २; ३; **६.** १८, ११; १९, १३; २१, ५; २२, ११; २४, ३; २७, ६; **७.** २४, १; २७, २; ३२, १७; २६; **८.** ४, १५; २१, १२; २४, ८; ९; ४६, १५; ६६, ६; ११; १३; ९८, १२; **१०.** ४२, ७; १०; ४३, २; ८४, ६; ९८, ९; १०२, १; १०४, १; १४७, ३; १८०, १.
पुरुऽहूतः **१.** १००, ६; ११; १८; १७७, १; **४.** १७, ५; **५.** ३०, १; **६.** १८, १; ३४, २; **८.** २, ३२; १६, ७; ११; **९.** ८७, ६; **१०.** १२८, ८.
पुरुऽहूतं **१.** ५१, १; **३.** ३०, १०; ३७, ५; ५१, १; **४.** २०, ५; **६.** २३, ८; ४७, ११; **७.** ३२, २०; **८.** १५, १; ९२, २; **१०.** ४१, १; १०४, १०.
पुरुऽहूता **६.** ६३, १.
पुरुऽहूताय **३.** ३५, २; **६.** ४५, २२.
पुरुहूते इति पुरुऽहूते **७.** २, ६.
पुरूचीः **३.** ५८, ८; **१०.** १८, ४.
पुरूणां **१.** ५, २; ३६, १; **५.** ७४, ७; **६.** ४५, २९.
पुरूणि **१.** ७२, १; ८४, १२; १२७, ४; १४८, ४; **२.** १९, ४; २५, ५; **३.** १५, ५; ३०, १३; ३२, ८; ३४, ५; ६; ३६, ८; ३८, ६; **४.** १६, १६; २३, ९; २९, १; **५.** ८, ५; **६.** १, १३[२]; ६, २; ४७, २; १४; ७२, ३; **७.** ४५, १; ५३, ३; ७०, ४; ५; **८.** ७८, ३; ९५, ६; ९६, २१; **९.** ८८, २; १०७, १९; **१०.** ४४, ७; ८०, २; ८९, १६; ९६, ६; १११, ४; ११३, १०; १२०, ७; १२४, ३.
पुरूरवः **१०.** ९५, २; ५; १५.
पुरूरवः **१०.** ९५, ७; ११.
पुरूरवसे **१.** ३१, ४.
पुरोळाः **३.** २८, २; **७.** १८, ६.
पुरोळाशं **१.** १६२, ३; **३.** २८, १; ३–६; ४१, ३; ५२, २–६; ८; **४.** २४, ५; ३२, १६; **६.** २३, ७; **८.** २, ११; ३१, २; ७८, १.
पुरोहिते इति पुरःऽहिते **६.** ७०, ४.
पुर्यं **१०.** १३८, ४.
पुलुऽकामः **१.** १७९, ५.
पुलुघः **१०.** ८६, २२.
पुषेम **१०.** १२८, १.
पुष्करऽस्रजा **१०.** १८४, २.
पुष्करात् **६.** १६, १३.

पुष्करिणीऽइव १०. १०७, १०.
पुष्करिणीं ५. ७८, ७.
पुष्करे ७. ३३, ११; ८. ७२, ११.
पुष्टं १. १०३, ५; ११४, १; १०. ५५, ४.
पुष्टंऽपुष्टं ९. ५५, १.
पुष्टयः २. २७, १२.
पुष्टऽवंतः ८. ४५, १६.
पुष्टस्य १०. ५५, ४.
पुष्टानि २. १२, ४.
पुष्टिः १. ६५, ३; २. ४, ४; ४. १६, १५.
पुष्टिंऽगो ८. ५१, १.
पुष्टिं १. ७७, ५; १२२, ७; २. १३, ४; ४. ३३, २; ५. १०, ३; ६. २, १; ६३, ६; ८. ४८, ६; ५९, ७.
पुष्टिऽमत् ३. १३, ७; १०. ८६, ३.
पुष्टिंऽभरार्य ४. ३, ७.
पुष्टिऽवर्धनः १. १८, २; ३१, ५; ९१, १२.
पुष्टिऽवर्धनं ७. ५९, १२.
पुष्टिषु १. १६६, ८.
पुष्टीः २. १२, ५.
पुष्टीनां १०. २६, ७.
पुष्टे १. १६२, ७.
पुष्टेः ४. ४१, १०; ५. ४१, २०.
पुष्टेषु १०. ८६, १.
पुष्टौ ५. ४१, ३; १०. ६१, २४.
पुष्ट्यै १०. १०५, ५; १०६, ४.
पुष्पंऽवतीः १०. ९७, ३.
पुष्पिणीः २. १३, ७; १०. ९७, १५; १४२, ८.
पुष्यत १. ९४, ८.
पुष्यतः १०. ९१, ३.
पुष्यतः १०. १३, ५.
पुष्यंता ५. ३४, ५.
पुष्यति १. ६४, १३; ८३, ३; ७. ३२, ९; १०. ७९, ५; ११७, ६; १३२, ३.
पुष्यति ३. १०, ३; ६. २, ५; ८. ३९, ७; ४१, ५; १०. ८३, १.
पुष्यंते १०. ११, ५.
पुष्यथ ४. ३६, १.
पुष्यन् २. २७, १५; ४. १२, २; ५. ३७, ४.
पुष्यंतः ४. ८, ५.
पुष्यंति १. ८१, ९; ५. ६, ६.
पुष्यंती ७. ५६, ५.
पुष्यंतु १०. १९, ३.
पुष्य १. १९१, १२.
पुष्यसि १. १६४, ४९.
पुष्यसि १. ९४, ६; ३. ४५, ३; ५. २६, ६; ६. २, १; ७. ३२, १६; ९. १००, २; ३; १०. १३३, २.
पुष्यसे ५. ५०, १; ६. १३, ५; ७. ५७, ५.
पुष्यात् ४. २१, १; ५. ३७, ५.
पुष्येम १. ६४, १४.
पूः १. १८९, २; ७. १५, १४; ५२, १; ९५, १; ८. ८०, ७.
पूःऽपतिं १. १७३, १०.
पूःऽभिः १. ५८, ८; १६६, ८; ५. ६६, ४; ६. ४८, ८; ७. ३, ७; १६, १०.
पूःऽभित् ३. ३४, १; ८. ३३, ५; ९. ८८, ४; १०. १०४, ८; १११, १०.
पूःऽभिदं ३. ५१, २; १०. ४७, ४.
पूःऽभिद्ये १. ११२, १४.
पूतः ९. ९७, ३१; १०९, ८; १०. १७, १०.
पूतऽक्रतायै ८. ५६, ४.
पूतऽक्रतौ ८. ६८, १७.
पूतऽदक्षः १. २४, ७; ३. १, ३.
पूतऽदक्षं १. २, ७; ७. ६५, १.
पूतऽदक्षसः ८. ९४, ७; १०; १०. ९२, ४.
पूतऽदक्षसा १. २३, ४; ८. २३, ३०; २५, १.
पूतऽदक्षसा ५. ६६, ४.
पूतऽदक्षाः ५. २९, १.
पूतऽदक्षान् ६. ५१, ९.
पूतऽबंधनी ५. ४४, ९.
पूतबंधू इति पूतऽबंधू ६. ६७, ४.
पूतं ३. २, १; ४. १, १९; १०, ६; ५. ८६, ६; ८. १२, ४; ९. ६७, ३१.
पूतस्य ८. ९४, ५.
पूताऽइव ७. ३, ९.
पूताः १. ७९, १०; ९. २२, ३; १०१, १२; १०. १८, २.
पूतासः १. ३, ४.
पूत्वी ८. ९१, ७.
पपुरंतु ७. ६२, ३.
पूयते ९. ८६, १२; ९७, ३५.
पूयमानः ९. ८७, ६; ९२, १; ९६, १०; १६; २१; ९७, १–३; ३६; ३९; ४२, ४८–५१; ५५.
पूयमानाः ४. ५८, ६.
पूयसे ९. ८६, ३०.
पूरवः १. ५९, ६; १३१, ४; ६. २०, १०; ७. ९६, २.
पूरवः १०. ४८, ५.
पूरवे १. ६३, ७; १३०, ७; ४. २१, १०; ७. ५, ३; १०. ४, १.
पूरुः ४. ३८, ३; ५. १७, १.
पूरुऽभ्यः ४. ३८, १; ३९, २.
पूरुं ७. ८, ४; १८, १३; १९, ३.
पूरुषु १. १०८, ८; ८. ६४, १०.
पूरोः १. १२९, ५.
पूरौ ६. ४६, ८.
पूर्णः १०. ११२, ६.
पूर्णऽगभस्ति ७. ४५, ४.
पूर्णं १. ८२, ४; १८२, २; ७. १०३, ७; ८. ७८, ७; १०. २९, ७; ४२, २; १००, ११.
पूर्णया १. १३५, ७.
पूर्णऽवंधुरः १. ८२, ३.
पूर्णा १. १५४, ४; ५. ५९, २; ७. ३७, ३.
पूर्णाः ४. ३७, २.
पूर्णां २. ३७, १; ७. १६, ११.
पूर्ते ६. १६, १८; ८. ४६, २१.
पूर्तयः १०. २२, ९.
पूर्तिः १०. १०७, ३.
पूर्ति ६. १३, ६.
पूर्धि १. ४२, ९; ८. ७८, १०; १०. ७३, ११.

पूर्धि १. ३६, १२; ७. २४, ६; ८. ९५, ४.
पूर्भर्तिऽतमं ८. ५३, १.
पूर्यमाणं १. ५१, १०.
पूर्वऽअपरं १०. ८५, १८.
पूर्वऽआयुषं ८. २२, २.
पूर्वः १. ६०, २; ९४, ८; १३९, ९; २. ३, ३; ३. १७, ५; ३८, ५; ४. ५०, ८; ७. ६, ३; २०, ७; १०. १७, ११; २७, ७; ३१, १०; ५३, १; ८७, ७; ९२, १५; १२६, ५; १४९, ३.
पूर्वःऽपूर्वः ५. ७७, २.
पूर्वगत्वाऽइव ७. ६७, ७.
पूर्वऽचित्तये १. ८४, १२; ११२, १; १५९, ३; ८. ३, ९; ६, ९; १२, ३३; २५, १२; ९. ९९, ५.
पूर्वऽजाः ८. ६, ४१.
पूर्वजावरी इति पूर्वऽजावरी १०. ६५, ८.
पूर्वजे इति पूर्वऽजे ७. ५३, २.
पूर्वऽजेभ्यः १०. १४, १५.
पूर्वऽतरां १. ११३, ११.
पूर्वऽथा १. ८०, १६; ९२, २; १३२, ४; ३. २९, १; ५. ४४, १; ८०, ६, ८. ३, ८; १५, ६; ९. ४३, २.
पूर्वऽपाः ४. ४६, १.
पूर्वपाःऽइव ८. १, २६.
पूर्वऽपाय्यं ८. ३४, ५.
पूर्वऽपीतये १. १९, ९; १३४, १; १३५, १.
पूर्वऽपीतिः १०. ११२, १.
पूर्वऽपेयं १. १३५, ४; ७. ९२, १.
पूर्वऽभाजः ५. ७७, १.
पूर्वऽभाजं ४. ५०, ७; ७. ९३, ४.
पूर्वं १. ३०, ९; ३१, ४; ३४, १०; १६६, १; २. ३७, २; ५. ३१, ११; ६. ४७, १५; ९. ९७, ५; १०. १८, ५; ६९, ४; १३९, २.
पूर्वया १. ८९, ३; ९६, २.
पूर्वऽयावा ३. ३४, २.
पूर्वऽवत् १. ३१, १७; ३. २, १२.
पूर्वऽसूनां २. ३५, ५.
पूर्वस्मात् १. ७४, ८.
पूर्वस्मै ८. २७, १०.
पूर्वस्य २. ४, ८; ५. ४७, ३; १०. २०, ७.
पूर्वऽहूतिं १. १२२, २.
पूर्वऽहूतौ १. १२३, २; ६. ६४, ५; ७. ३५, ५; ३९, २; १०. ११३, ७.
पूर्वा १. १२३, २; १८५, १; २. २७, १०; ४. ३८, १; ६. ५९, ६; १०. ५६, ५.
पूर्वाः १. ४४, १०; ११३, १०; १४१, ५; ३. ५५, १; ७. १८, २०; ९. ६८, २; १०. ९७, १.
पूर्वाणि ४. १९, १०; ५. ३१, ६; ७. ७०, ४; ८. २५, १७.
पूर्वान् १०. ६९, १०.
पूर्वान्ऽइव ५. ५३, १६.
पूर्वाभिः १. १०४, ४; ५. ४८, २.
पूर्वां १. ९५, ३; १२४, ९; १२६, ५; ९. १११, ३.
पूर्वासः ९. ७७, ३; १०. १५, २.
पूर्वासां १. १२४, ९.
पूर्वासु ३. ५५, ५; ८. २०, १५.
पूर्वाह्णे १०. ३४, ११.
पूर्वी इति ७. २, ५; १०. २९, ६.
पूर्वीऽइव १०. ६१, २५.
पूर्वीः १. ११, ३; ५६, १; ५९, ४; ६३, २; ७०, १; ४; १७४, ८; १७९, १; १८१, ६; २. ११, २; १४, ६; ३. १, १०; ११; ४, ५; ५, २; ६, ७; ७, ९; १४, ६; १५, ३; २०, २; ३; ३०, १८; ३१, १४; ३६, ५; ३८, ५; ४३, २; ५१, ५; ५४, १४; ४. १६, १९; १७, ११; १८, ४; १९, ८; २१, १; २२, ४; २३, ३; ८; ५. २, २; १२, २; २७, ३; ६. १, १२; २४, ३; २८, १; ३४, १; ३९, ४; ५; ४४, ९; ११; ४५, ३; ४७, १७; ६३, ७; ७. २१, ३; २६, ४; ३१, १०; ३२, १३; ४८, ३; ९१, २; ८. ५, ३१; २६, ३; ४०, ९; ५२, ९; ६२, २; ६६, १२; ९६, १०; ९. ७१, ७; ७८, २; ८५, ११; ८७, ९; ८९, ५; १०. २९, ५; ८; ३१, ७; ४६, १०; ६८, १२; ७७, २; ९८, १०; १११, १०; १२३, ३.
पूर्वीभिः १. ८६, ६; ५. ३९, ४; ७. ६७, ३; ८. २२, १६.
पूर्वीषु ५. ३५, ६.
पूर्वे १. ४८, १४; ६२, २; ९२, १; १२४, ५; १३९, ९; १६४, ५०; १७९, २; ३. ५५, २; ५. ३, ८; २५, २; ४२, ६; ६. १९, ४; २२, २; २७, ५; ७. २१, ७; २२, ९; ५३, १; ९. ९६, ११; ९७, ३९; १००, १; १०. ५, ७; १४, २; १५, ८; ५१, ६; ५४, ३; ८२, १; ४; ९०, १६; ९४, २; ९८, ९; १०९, ४; १२८, ३; १३०, ६; १९१, २.
पूर्वेण १०. १३४, ९.
पूर्वेभिः १. १, २; १०. ९६, ५.
पूर्वेभ्यः १. १७५, ६; १७६, ६; ९. ८२, ५; १०. १४, १५.
पूर्वेषां ६. ४७, १७; ७. २९, ४; १०. ९६, १३; १३०, ७.
पूर्वैः १०. १५, १०; १५४, ४.
पूर्वौ ५. ६५, ३.
पूर्व्यं १. २६, ५.
पूर्व्य २. २, ९; ८. ३, ११; ३९, १०; ९. ३६, ३.
पूर्व्यः १. ७४, २; ९४, ६; १५३, ४; ३. ११, ३; ३२, १०; ६. १४, १; २०, ११; ३७, २; ८. ७, ३६; २७, ३; ३९, ३; ६३, १; ७५, १; ९. २, १०; ६७, ८; ७७, २; ८६, २०; ९६, १०; १०९, ७; १०. ४८, १.
पूर्व्यां १. १८०, ३; ८. ३, ७; १९, २; २२, २; ४६, २०; १०. ४९, १.
पूर्व्ये १. १०५, ४; १२१, ३; १४२, १; १५६, ३; २. २२, ४; ३.

१०, ५; १४, ३; २३, ३; ३१, ६; ४. ५, ९; १६, ८; ५. ८, २; २०, ३; ३५, ६; ५५, ८; ८. १३, १४; २२, ६; २३, ७; २२; ३९, ८; ४१, ४; १०; ५२, ९; ६०, २; ७९, ६; १०२, १०; ९. ६, ३; ११०, ८; १०. १३, १; ७२, ९.

पूर्व्यऽस्तुतिः ७. ९४, १.

पूर्व्यऽस्तुतिं ८. २४, १७; ३५, १९.

पूर्व्या १. ११७, ४; २. ११, ६; ३. ३९, २; ४. ४४, ५; ७. ६, २; १०. ३१, ६; ३२, ४.

पूर्व्याः २. ३६, ६; ३. ५४, ४.

पूर्व्याणि १. ६१, १३; ११७, २५; २. २०, ५; ३. ५५, ३; ४. ५५, २; ६. ४, ३; १०. ११२, ८.

पूर्व्यान् ३. ३६, २.

पूर्व्याभिः ६. ४४, १३.

पूर्व्यां ८. ६, ४३; ६८, ७.

पूर्व्याय १. ११८, ८; १५६, २; ३. १, २०; ४. ४१, ७; ४४, ३; ५. १५, १; ३; ४५, ३.

पूर्व्यासः १. ३५, ११; ७. ७६, ४.

पूर्व्यै १. १३२, १.

पूर्व्ये ९. ७०, १; १०. ७२, २.

पूर्व्येण ८. ५७, १.

पूर्व्येभिः १. ११७, १४; ३. ३२, १३; १०. १४, ७.

पूर्षु २. ३५, ६.

पूषणः १०. ९३, ४.

पूषणं १. १४, ३; ४२, १०; १०६, ४; १८६, १०; ५. ४६, ३; ६. २१, ९; ४८, १५; ५४, ८; ५५, ४; ६; ५६, १; ५७, ६; ७. ३६, ८; ४१, १; ४४, १; ८. ४, १५; १०. ३३, १; ३५, ११; ६४, ३; ७; १२५, २.

पूषणस्य १०. ५, ५.

पूषणा ६. ५७, १.

पूषण्ऽवते १. १४२, १२; ३. ५२, ७.

पूषण्ऽवन्तः ३. ५४, १२.

पूषण्ऽवान् १. ८२, ६.

पूषन् १. ४२, ७–९; ९०, ५; ६. ५२, ३; ५४, ६; ९; ८. २७, ८.

पूषन् १. २३, १३; ४२, १; २; ५; १३८, २–४; १८४, ३; ३. ६२, ७; ६. ४८, १६; १९; ५३, १; ६; ८; ५४, १; ५६, ५; ५८, १; ३; ७. ४०, ६; ८. ४, १७; १८; १०. २६, ४; ८; ८५, ३७.

पूषऽरातयः १. २३, ८; २. ४१, १५.

पूषर्यौ १०. १०६, ५.

पूषा १. २३, १४; ८९, ५; ६; ९०, ४; २. १, ६; ३१, ४; ४०, ६; ३. ५७, २; ६२, ९; ४. ३०, २४; ५७, ७; ५. ४१, ४; ४६, २; ५; ४९, ३; ५१, ११; ८१, ५; ६. १७, ११; २४, ५; ४९, ८; ५०, ५; ५१, ११; ५४, ४; ५[३]; १०; ५७, ४; ५८, २; ४; ७५, १०; ७. ३५, ९; ३९, २; ८. ३१, ११; ५४, ४; ९. ६७, १०; ८१, ४; १०१, ७; १०. १७, ३–६; २६, १; ३; ९; ५९, ७, ६५, १; ६६, ५; ८५, १४; २६; ९२, १३; ९८, १; १३९, १.

पूषाऽइव १. १८१, ९; ६. ६१, ६; ९. ८८, ३.

पूष्णः १. १३८, १; १६२, ३; ४; ५. ४३, ९; ६. ५४, ३; ५७, ५.

पूष्णा ६. ५४, २.

पूष्णे १. १२२, ५; ४. ३, ७; ९. ६१, ९; १०९, १.

पृक्षः १. ३४, ४; ४७, ६; ७१, ७; ७३, ५; १३९, ३; ४. २३, ९; ४३, ५; ४४, २; ५. ७३, ८; ७५, ४; ७७, ३; ६. ३५, ४; ७. ३६, ५; ७४, ५; ९०, ५; १०. १०६, १.

पृक्षः १. १४१, २; १७८, ४; २. १, ६; १५; ६. ६३, ७; ७. ३७, ६; ८. २३, ३.

पृक्षऽप्रयजः ३. ७, १०.

पृक्षे ६. ६२, ४.

पृक्षं १. १२७, ५; १२९, २; २. ३४, ३; १०. ९३, १०[१].

पृक्षऽयामेषु १. १२२, ७.

पृक्षसे १०. २२, ७.

पृक्षस्य ६. ८, १.

पृक्षाःऽइव १०. ६५, ४.

पृक्षाय २. १३, ८.

पृक्षासः ३. ४, ७; ४. ४५, १; २; ६०, ४.

पृक्षुधः १. १४१, ४.

पृक्षे १. ६३, ३; १८३, २; २. ३४, ४.

पृक्षेण १०. २८, ३.

पृंक्त १. १०९, ४; २. ३७, ५; ६. ६८, ८; ७. ९३, २.

पृंक्तं ८. ५, ३६.

पृंक्ते १०. ९५, ९.

पृङ्धि २. २४, १५.

पृचः ५. ७४, १०.

पृचानः ९. ९७, ११.

पृचीमहि १. १२९, ७.

पृच्छ १. ४, ४; ३. ३८, २; ४. १८, ६.

पृच्छत् ८. ४५, ४; ७७, १.

पृच्छतं १०. ८१, ४.

पृच्छत १. १४५, १.

पृच्छति १. १४५, २.

पृच्छते ९. ८९, ३; १०. २२, ६.

पृच्छन्तः ६. २१, ६.

पृच्छन्ति २. १२, ५.

पृच्छन्ति १. १४५, २.

पृच्छन्ती ६. २२, ५.

पृच्छमानः ७. १, २३; १०. ३४, ६.

पृच्छमानाः ९. ९७, ३४; ३५.

पृच्छमानौ १०. ८५, १४.

पृच्छसि १०. १४६, १.

पृच्छसे १. १६५, ३.

पृच्छात् ८. २४, ३०.

पृच्छान् १०. ३१, १०.

पृच्छामि १. १६४, ३४[४]; १०. ७९, ६; ८८, १८.

पृच्छामि १. १०५, ४; १२०, ४; १६४, ५; ६.

पृच्छे ७. ८६, ३; १०. ४०, ५.

पृच्छेत् १. १२०, २.

पृच्छे ४. १८, २.

पृच्छ्यमानः ४. ३, ८; ५, ११.

पृच्छ्यमाना **८.** ४०, ३.
पृच्यतां **६.** २८, ८.
पृच्यते **९.** ६९, २.
पृच्यते **१.** १०३, १; **८.** ५१, ७.
पृंचतीः **१.** २३, १६.
पृंचते **१.** १२८, ५.
पृंचन् **९.** ९७, १२.
पृंचंतः **७.** ६७, ९.
पृंचंतं **८.** २४, १४.
पृंचंता **१.** ४७, ८.
पृंचंति **५.** ७४, १०; **१०.** ९४, १३.
पृंचंति **१.** ७९, ३.
पृंचीत **१.** ४०, ८.
पृण **१.** १६, ९; ५७, ५; **३.** ३०, १९; **६.** ४५, २१; **८.** १, १८; २४, ६; ६४, ६; **९.** ४१, ५.
पृणक् **६.** २०, ६.
पृणकु **४.** ३८, १०.
पृणक्तु **१.** ८४, १.
पृणक्षि **१०.** १४०, २; ४.
पृणक्षि **१.** ८३, १; **६.** १५, ११.
पृणत **२.** १४, १०; ११.
पृणतः **१.** १२४, १०; १६८, ७; **१०.** ११७, १.
पृणतां **३.** ५०, १.
पृणति **३.** ३६, ६.
पृणति **६.** २९, ५; ३७, ५.
पृणते **६.** २८, २; **७.** ३२, ८; **१०.** १२२, ४.
पृणध्यै **६.** ६७, ७.
पृणध्वं **३.** ३३, १२.
पृणध्वं **१.** १६२, ५; **७.** १६, ११; ३७, १.
पृणन् **७.** ३२, ८; **१०.** ११७, ७.
पृणंतः **१.** १२५, ७; **२.** ११, ११.
पृणंतं **१.** १२५, ४; **१०.** ११७, ४; १२२, ४.
पृणंति **१.** ५२, ४; **५.** ८५, ६; **६.** ६७, ७; **८.** ४९, ३; **१०.** ९६, २; १०७, ३; ४.
पृणंति **२.** ३५, ३; **५.** ११, ५; **६.** ४, ७; **१०.** ८६, १४; १०७, ३.
पृणंती **१.** १२४, ५.
पृणस्व **६.** ४१, ४; **१०.** १०४, २.
पृणात् **२.** ३०, ७.
पृणात् **६.** ४७, १५.
पृणाति **१.** १२५, ५; **१०.** २८, २.
पृणाति **१०.** २, ४.
पृणासि **८.** ६४, ४; **१०.** ९५, ५.
पृणीत **१.** २३, २१.
पृणीतः **१०.** ११७, ९.
पृणीतन **५.** ५, ५.
पृणीतं **७.** ६५, ४.
पृणीयात् **१०.** ११७, ५.
पृणेथां **६.** ६९, ७.
पृणैथे इति **७.** ६१, २.
पृतनाः **२.** ४०, ५; **३.** २४, १; ३४, ४; **६.** ७५, ५; **७.** २०, ३; **८.** ३६, १; ३७, २; ९६, ७; ९७, १०; **१०.** २९, ८; १०४, १०; १२८, १.
पृतनाजः **९.** ८७, ५.
पृतनाजं **१०.** १७८, १.
पृतनाज्ये **३.** ३७, ७; **८.** १२, २५.
पृतनाज्येषु **३.** ८, १०; **७.** ९९, ४; **१०.** १०२, ९.
पृतनानां **८.** ७०, १.
पृतनाऽयंतं **१.** १६९, ७.
पृतनाऽयवः **८.** ४, ५.
पृतनाऽयून् **३.** १, १६; **७.** १, १३; **१०.** ६९, ६.
पृतनाषाट् **१.** १७५, २; **३.** २९, ९; **६.** १९, ७; **९.** ८८, ७; **१०.** १०३, ७.
पृतनाऽसहः **६.** ४५, ८.
पृतनाऽसहं **५.** २३, २; **६.** ७२, ५; **८.** ९८, १०.
पृतनाऽसह्याय **३.** ३७, १.
पृतनासु **१.** ८५, ८; ९१, २१; १०२, ९; १११, ३; ११९, १०; १२९, २; १३१, ५; १५२, ७; १५७, २; **२.** २३, ११; **३.** १६, २; ४९, २; **४.** ३६, ६; ४१, ११; **५.** ८६, २; **६.** १९, ८; ४१, ५; ४८, १९; ६८, ७; **७.** ८, ४; ५६, २२; २३; ५९, ४; ८२, १; ४; ९०, ६; **८.** ३२, १४; ४६, ८; ६०, १२; ६१, १२; ७०, ४; **९.** ९०, ३; **१०.** २९, ८; ८३, ४; ८७, १९.
पृतनाऽहवेषु **१.** १०९, ६.
पृतन्यतः **१.** ८, ४; १३२, १; **२.** ८, ६; **८.** ४०, ७; ८६, ५; **९.** ३५, ३; ६१, २९; **१०.** ४३, ६; १५२, ४.
पृतन्यति **९.** ५३, ३.
पृतन्यंतं **१०.** १७४, २.
पृतन्यसि **१.** ५४, ४.
पृतन्यात् **१.** १३२, ६; **१०.** २७, १०.
पृतन्युं **१.** ३३, १२.
पृतन्यून् **४.** २०, १; **७.** ६, ४; **९.** ११०, १२; **१०.** ७४, ५.
पृतऽसु **१.** २७, ७; ५४, १; ६४, १४; ७९, ८; १२२, १०; १७३, १२; १७८, ३; **२.** ११, १५; २६, १; २७, १५; **३.** ४९, ३; ५४, २२; **५.** ९, ७; **६.** २०, १; ३३, ३; ४; ४४, १८; ४६, ८; ७३, २; **८.** ९, १३; १५, ४; २०, २०; ३१, १५; ६१, ३; ६८, ९; ९२, ११; **९.** ८, ८; ९६, ८.
पृत्सुतिः **१.** १६९, २.
पृत्सुतीः **१.** ११०, ७; **५.** ४, १.
पृत्सुतूर्षु **३.** ३७, ७.
पृत्सुतौ **१०.** ३८, १.
पृत्सुषु **१.** १२९, ४.
पृथक् **१.** १३१, २[२]; १५७, १; **२.** १७, ३; २४, १४; **३.** ५६, ४; **८.** ४३, १८; २९; १००, ७; **९.** ८६, २; **१०.** ४४, ६; ९१, ७; १०१, ४; १४२, ४.
पृथवाने **१०.** ९३, १४.
पृथि **१.** ११२, १५.
पृथिवि **६.** ५१, ५.
पृथिवि **१.** २२, १५; **२.** ३१, ५; **३.** ५४, ४; **५.** ६६, ५; ८४, १; **६.** ६८, ४; **१०.** १८, ११; ५९, ८.
पृथिविऽस्थाः **७.** १८, २३.
पृथिवी **१.** २२, १३; ३७, ८; ३९, ६; ५२, ११; ५५, १; ५७, ५; ७२, ९; ८९, ४; ९४, १६; ९५,

११; ९६, ९; ९८, ३; १००, १९; १०१, ११; १०२, २; ११; १०३, ८; १०५, १९; १०६, ७; १०७, ३; १०८, १३; १०९, ८; ११०, ९; १११, ५; ११२, २५; ११३, २०; ११४, ११; ११५, ६; १२१, १; १६४, ३३; ४७; १९१, ६; **२.** १२, १३; **३.** ६, ३; ८, ८; ३६, ४; ५१, ५; ५४, १९; ५५, २२; **४.** १६, ७; ५१, ११; **५.** ४२, १६; ५४, ९; ५६, ३; ५८, ७; ६०, २; ८३, ५; **६.** ५०, १३; १४; ५१, ११; ६६, ९; ७०, ६; **७.** ५, ४; ७, ५; ३४, ७; २३; ३६, १; १०४, २३; **८.** १५, ८; ४०, ४; ५४, ४; **९.** ८६, ९; **१०.** १०, ५; १८, १२; २९, ६; ३६, २; ५९, ७; ६०, ९; ८५, २; ८८, २; ८; १२१, ५; १४७, १; १७३, ४.

पृथिवी इति **१.** ६३, १; १४३, २; १५९, १; **२.** ४१, २०; **५.** ४३, २; **६.** ११, १; **७.** ४३, १; **८.** ९७, १४; **१०.** ३५, ३; ४६, ९; ९१, ३.

पृथिवी इति **१.** १८५, २–८.

पृथिवीः **१.** ३४, ८; **४.** ५३, ५; **७.** १०४, ११.

पृथिवीद्यावा **३.** ४६, ५.

पृथिवीं **१.** ३४, ७; ३८, ९; ६७, ३; ७३, ३; १०३, २; १३१, ४; १५४, ४; **२.** १२, २; १३, ५; १५, २; १७, ५; **३.** ३०, ११; ३२, ८; ३४, ८; ४४, ३; ५५, २१; ५९, १; ७; **४.** ३६, १; **५.** ४२, १६; ४६, ३; ५४, ८; ५७, ३; ६२, ३; ८३, ४; ८५, १; ४; ५; **६.** ४७, २९; ५१, ८; ७२, २; **७.** १८, ८; ९९, ३; १००, ३; ४; **८.** २७, २; ८९, ५; १०३, २; **९.** ८६, २९; ९७, १३; १००, ९; **१०.** १६, ३; १८, १०; १३; २७, २३; ५५, १; ५८, २; ६२, ३; ६३, १०; ६५, ४; ११; ८१, ६; ८८, ३; ८९, ४; ९४, ४; १२; ९७, १९; ११९, ८–१०; १२१, १; १४९, १; १९०, ३.

पृथिवीऽइव **९.** १७, २.

पृथिव्या **३.** ६२, २; **४.** १९, ८; **६.** ५२, १; **८.** ३५, २; **१०.** १०, ९; ८२, ५; १६८, १.

पृथिव्याः **१.** २२, १६; ३२, ५; ३३, ८; १०; ३५, ८; ३८, २; ३९, ३; ५२, १३; ५६, ६; ५९, २; ६१, ९; ६५, ४; ८०, १; १००, १; १०९, ६; १४३, ४; १६४, ३४; ३५; १७३, ३; **२.** ३, ७; ३१, २; ३८, ११; ४०, १; **३.** १, ३; ५, ९; ६, २; ७, १०; ८, ३; १७, २; २३, ४; २५, १; २९, ४; ४६, ३; ५३, ११; ५९, ३; ६१, ४; **४.** २१, ३; ३९, १; ४४, ५; ५४, ४; **५.** ६३, ३; **६.** ७, १; ११, ५; १८, १२; २१, २; ३०, १; ४४, २१; ४७, ४; २७; ४८, ५; ४९, ६; ५८, ४; ७१, ५; **७.** ५, १; ६, ७; ७, २; २४, ३; ३४, २; ३८, ५; ३९, ५; ६०, ७; ६१, ३; ९७, १; ९९, १; २; १०४, ४; **८.** २५, १८; ३६, ४; ४२, १; ४४, १६; ५७, ३; ७९, ४; **९.** ८, ८; ३१, २; ५७, ४; ६३, २७; ७२, ७; ७९, ४; ८२, ३; ८६, ८; ८७, २; ८९, ६; ९६, ५; **१०.** १, ६; ७, १; १७, ६; २८, २; २९, ७; ४६, ८; ५६, ७; ६३, २; ७०, १; ५; ७७, ३; ८९, १०; १४; १०९, ७; ११०, ४; १११, ५; १२१, ९.

पृथिव्यां **१.** ९१, ४; ९८, २; १००, १८; १०८, ९–११; १३९, ११; १४३, १; १६८, ८; १९०, ४; **२.** ३, १; १७, ६; ४०, ४; **३.** ८, १०; १४, १; २२, २; **४.** ५, ११; **५.** ८३, ९; **६.** १, ५; १९, १२; **७.** ३, ४; ५, २; ८, २; ६४, १; ७०, १; **८.** ४१, ४; ४९, ७; **१०.** ४९, ९; ७३, ९; १८३, ३.

पृथिव्यै **१.** १८५, १०; **३.** ५४, २; ३; **४.** ३, ५; **५.** ५९, १; **९.** १०९, ५.

पृथीं **८.** ९, १०.

पृथु **१.** ९, ७; ४६, ८; ४८, १५; ५०, ७; १०१, ७; **२.** २४, ११; **४.** २, १३; **५.** ६६, ५; ८७, ७; **६.** १६, १२; **७.** ५, ८; १०, १; ३६, १; **८.** ९, १; ६५, ११.

पृथुः **१.** १२३, १; **२.** १, १२; २१, ४; **५.** १२, ६; **६.** १९, १; **८.** ४५, २; ९८, ४.

पृथुऽग्मानं **१०.** ९९, १.

पृथुंऽजघने **१०.** ८६, ८.

पृथुऽज्रयं **४.** ४४, १.

पृथुऽज्रयसे **१०.** ३०, १.

पृथुऽज्रयाः **३.** ४९, २.

पृथुऽज्रयी **१.** १६८, ७.

पृथुना **३.** १५, १.

पृथुऽपक्षसा **८.** २६, २३.

पृथुऽपर्शवः **७.** ८३, १.

पृथुऽपाजसः **३.** ६१, २.

पृथुऽपाजसा **४.** ४६, ५; **८.** ५, २.

पृथुऽपाजसे **३.** ३, १.

पृथुऽपाजाः **३.** २, ११; ५, १; २७, ५.

पृथुऽपाणिः **१.** ३८, २.

पृथुऽप्रगानं **३.** ५, ७.

पृथुऽप्रगामा **१.** २७, २.

पृथुऽबुध्नः **१.** २८, १.

पृथुऽबुध्नः **४.** २, ५.

पृथुऽबुध्नं **१०.** ४७, ३.

पृथुऽबुध्नासः **१.** १६९, ६.

पृथुं **१.** ३७, ११; **२.** १०, ४; **८.** ४५, ३०; **९.** ३५, १; **१०.** ९९, २; ११३, ४; १५६, ३.

पृथुऽयामन् **६.** ६४, ४.

पृथुऽश्रवसः **१.** ११६, २१; **८.** ४६, २४.

पृथुऽश्रवसि **८.** ४६, २१.

पृथुंऽस्तुके **२.** ३२, ६.

पृथुस्तो इति पृथुंऽस्तो **१०.** ८६, ८.

पृथू इति **६.** १९, ३.

पृथूनि **६.** ६, २; **१०.** १०१, ८.

पृथौ **१०.** १४३, ४.

पृथ्यांः १०. १४८, ५.
पृथ्वी १. ६५, ३.
पृथ्वी इर्ति १. १८५, ७; ४. २३, १०; ६. ७०, १; ४; १०. १७८, २.
पृथ्वीः ७. ३४, ३.
पृथ्वीं ४. ४, १; ६. १२, ५; ७. ३८, २; १०. ३१, ९.
पृदांकुऽसानुः ८. १७, १५.
पृशनऽयुवः १. ८४, ११.
पृशनी १०. ७३, २.
पृशंने ९. ९७, ५४.
पृशन्यंः १. ७१, ५; १०. ६१, ८.
पृश्नंयः १. ८४, ११; ८. ६, १९; ७, १०; ६९, ३.
पृश्निः १. १६८, ९; ४. ३, १०; ५. ४७, ३; ६०, ५; ६. ६६, १; ३; ७. ३५, १३; ५६, ४; १०३, ४; ६; १०; ९. ८३, ३; १०. १०५, १०; १८९, १.
पृश्निंऽगर्भाः १०. १२३, १.
पृश्निंऽगावः ७. १८, १०.
पृश्निंऽगुं १. ११२, ७.
पृश्निंऽनिप्रेपितासः ७. १८, १०.
पृश्निं १. १६०, ३; १६४, ४३; ५. ५२, १६.
पृश्निंऽमातरः १. २३, १०; ८५, २; ८९, ७; ५. ५९, ६; ८. ७, ३; १७; ९. ३४, ५.
पृश्निऽमातरः १. ३८, ४; ५. ५७, २; ३.
पृश्नेः ४. ५, ७; १०; ५. ५८, ५; ६. ६, ४.
पृश्न्यांः २. २, ४; ३४, २; १०; ६. ४८, २२.
पृर्षत्ऽअश्वः १. ८७, ४.
पृर्षत्ऽअश्वाः १. ८९, ७.
पृषत्ऽअश्वाः ७. ४०, ३.
पृर्षत्ऽअश्वान् ५. ४२, १५.
पृर्षत्ऽअश्वासः १. १८६, ८; २. ३४, ४; ३. २६, ६.
पृषत्ऽआज्यं १०. ९०, ८.
पृर्षती इर्ति १. १६२, २१.
पृर्षतीः १. ३९, ६; ८५, ४; ५; ३. २६, ४; ५. ५५, ६; ५७, ३; ८. ७, २८.
पृर्षतीनां ८. ६५, १०; ११.
पृर्षतीभिः १. ३७, २; ६४, ८; २. ३४, ३; ३६, २; ५. ५८, ६.
पृर्षतीषु ५. ६०, २.
पृर्षत्ऽयोनिः ५. ४२, १.
पृर्षत्ऽवत् ७. २, ४.
पृषध्रे ८. ५२, २.
पृषंतं ४. ५०, २.
पृष्टः १. ९८, २; ३. ४९, ४; ७. ५, २.
पृष्टबंधो इर्ति पृष्टऽबंधो ३. २०, ३.
पृष्टिऽआमयी १. १०५, १८.
पृष्टीः १०. ८७, १०.
पृष्ठं १. ५८, २; ११५, ३; १६६, ५; २. १३, ४; ३. २, १२; ४. ५, ६; ९. ३६, ६; ६९, ५; ८३, २; १०. १२३, २.
पृष्टऽयज्वने ५. ५४, १.
पृष्ठा ९. १४, ७.
पृष्ठाऽइंव ४. २, ११; ५. ७, ५; १०. ८९, ३.
पृष्ठात् ६. २४, ६.
पृष्ठानि ९. २२, ५.
पृष्ठे १. १२५, ५; १६४, १०; ५. ३६, २; ६१, २; ६. ७५, ५; ८. १००, ५; ९. ६६, ५; ८६, २७.
पृष्ठेर्षु ९. १०२, ३.
पृष्ठ्येन ४. ३, १०; २०, ४.
पेचे ४. १८, १३.
पेतथुः १. १८२, ५; ८. ७३, ४.
पेत्वेन ७. १८, १७.
पेदवे १. ११७, ९; ११८, ९; ११९, १०; १०. ३९, १०.
पेपिंशत् १०. १२७, ७.
पेयाः ५. २९, ३; ९. १०९, २.
पेरवः ९. ७४, ४.
पेरुः १. १५८, ३; ७. ३५, १३.
पेरुके ६. ६३, ९.
पेरुं १०. ३६, ८.
पेरुं ५. ८४, २.
पेशंः १. ६, ३; ९२, ५; २. ३, ६; ४. ३६, ७; ७. ३४, ११; ४२, १.
पेशंनानि १०. १, ६.
पेशांसि १. ९२, ४.
पेर्षी ५. २, २.
पैजऽवनस्य ७. १८, २२; २३; २५.
पैद्वः १. ११६, ६; ९. ८८, ४.
पोतां १. ९४, ६; २. ५, २; ४. ९, ३; ७. १६, ५.
पोता ९. ६७, २२.
पोत्रं १. ७६, ४; २. १, २.
पोत्रात् १. ५, २; २. ३६, २; ३७, २; ४.
पोप्रुथत्ऽभिः १. ३०, १६.
पोषं १. १, ३; ९३, २; १६६, ३; २. २१, ६; ४०, ४; ४. ३३, १०; ३६, ६; ८. २३, २१; ५१, ६; ५९, ७; ९. ६५, १७; ६६, २१; १०. १७, ९; ३६, ७; ७१, ११.
पोषयत् ५. ९, ७.
पोषयिलु ३. ४, ९; ४. ५७, १.
पोषांय १. १४२, १०.
पोषें ५. ५, ९.
पोषेण १. १२५, १.
पोष्यं ८. ९७, ३.
पोष्यां १. ११३, १५; ८. २६, २०.
पोष्यांणां ४. ४८, ५.
पोष्याऽवंतः ५. ४१, ८.
पौंस्यं १. ८०, १०; १०१, ३; १५५, ३; ४; २. १३, १०; ४. ३०, ८; २३; ५. ३५, ४; ८. ३, २०; ६, ३१; ७, २३; १५, ८; ३२, ३; ४५, २६; ५१, ४; ६३, ३; ६६, ९; ९३, १५; ९. ९९, १; १०. ७६, २; ११३, ४.
पौंस्यां १. ५, ९; १३९, ८; १६६, ७; ४. ३२, ११; ५. ५९, ४; ६. ४६, ७; ८. ६३, ८; ९५, ६; ९. १११, ३; १०. ९३, १३.
पौंस्यानि १. १६९, ६; ६. ३६, ३; १०. ५५, ७.
पौंस्यांय ७. ३०, १.

पौंस्यें **१.** ५६, ३; **४.** ४१, ६; **१०.** ५०, ३; ९२, ७.

पौंस्येभिः **१.** १००, ३; १०; १६५, ७; **६.** ६६, २.

पौंस्यैः **१०.** २९, ७; ५९, ३.

पौतऽक्रतः **७.** ५६, २.

पौरं **५.** ७४, ४.

पौरः **२.** ११, ११; **८.** ६१, ६.

पौरं **५.** ७४, ४; **८.** ३, १२.

पौराय **५.** ७४, ४.

पौरासः **८.** ५४, १.

पौरुऽकुत्सिं **७.** १९, ३.

पौरुऽकुत्स्यः **८.** १९, ३६.

पौरुऽकुत्स्यस्य **५.** ३३, ८.

पौरुषेय **८.** ७१, २.

पौरुषेयीं **७.** ४, ३.

पौरुषेयेण **१०.** ८७, १६.

पौरे **८.** ५०, ५.

प्यायंतां **१.** ९३, १२.

प्यायसे **१०.** ८५, ५.

प्यायस्व **१.** ९१, १६; १७; **९.** ६७, २८.

प्र **१.** ३, १२; ४, ८; ५, १; १०, ११; ११, २; १३, ११; १४, ४; १५, ९; १७, ९; १९, १; २१, २; २३, २२; २४, ९; ११; २५, १; ६; १२; २७, ४; ३१, ८; १४^{२}; १८; ३२, १^{२}; ४; ३३, ५; ७; १३; १४; ३४, ११; ३६, १; ३; ११; १७; ३७, १; ४; ५; ११; १४; ३८, १०; ३९, १; ५; ४०, १; ३; ५; ४१, ५; ४२, १; ९; ४७, ५; ४८, ४; १५^{२}; ४९, २; ३; ५१, ५; ५३, १; ५४, ८; ५५, ३; ५६, १; ५७, १; ५९, ५; ६; ६०, ५; ६१, १; २; ९; १२; १३; १५; ६२, १; २; ६४, १; ३; १३; ६६, ५; ६७, ४; ७१, १; १०; ७२, ४; १०; ७४, ८; ७६, ३; ७८, १–५; ७९, १०; ८०, ३; ८१, १; ८२, ३; ६; ८३, २; ८४, १९; ८५, १; ५; ६; ८७, ३; ५; ८९, २; ९१, १; १९; ९४, १६; ९५, ३; ९६, ८; ९७, ३–५; १०१, १; १०२, १; ३; ४; १०४, ४; ८; १०९, ५; ६^{४}; ११०, २; ११२, ५; ८; १३; २३^{२}; ११३, १६; ११४, १; ११६, १; १०; १२; २५; ११७, २२; २३; २५; ११९, ६; ७; १२०, ३; ५^{२}; १२१, १; ६^{२}; १४; १२२, १; ४^{२}; ५; १२४, १^{२}; ५; १०; ११; १२५, ६; १२६, १; १२७, २; ४; १०; १२९, १; ६; १३०, ८; ९; १३२, ५; १३४, ३^{२}; १३५, १; १३६, १; १३८, २; १३९, १; १४०, १; ५; ८; १४१, ४; १४३, १; २; १४४, १; १४८, ३; १४९, २; १५१, २; ३; ४; १५२, ५; १५४, १–३; १५५, १; १५७, १; ४; १५८, १; ४; १५९, १; १६१, ९; १२; १६२, ७; १९; १६३, १२; १३; १६४, १८; २५; २६; १६५, १३; १६६, ४; ५; ७; १६७, ७; १६९, ६; १७०, ५; १७३, २; ४; ६; १७४, ५; ६; ९; १७६, ५; १७७, ४; १८०, ९^{२}; १८१, ५; ६; १८६, ९^{२}; १०; १८७, ५; १९०, ३; १९१, १५; **२.** १, १५; १६; २, १३; ३, १०; ९, ३; ११, ३; १४; १३, २; ११; १२; १५, १; ५; ९; १६, १; ७; १७, ३; १९, २; ३; २०, १; २१, ३; २२, २^{२}; ४; २३, १०; २४, २; ८; १२; २५, १; २६, ४; २८, ४; २९, ५; ३०, २; ३; ६; ३१, १; ३३, १; ८; ३५, ८; ३८, २; ४१, १९; **३.** १, २०; २२; ३, ८; ४, ३; ५; ५, २; ६, १; २; ७, १^{२}; ३; १०, ५; १२, ५; ७; ९; १३, १; १५, ६; १७, २; ५; १९, १; २; २१, १; ५; २६, ४^{२}; २७, १; ८; २८, ४; २९, १४; ३०, ६^{२}; १०; ३१, ८; १६; २१; ३२, ६; ३३, १; ५; १२; ३४, २–५; ९; ३६, ५; ६; ९; १०; ४०, ३; ४; ४३, ६; ७; ४५, ३; ४६, ३^{४}; ५१, ४; १२^{३}; ५२, ५; ५३, ६; ७; ११^{२}; ५४, १; ३; ५; १०; ५५, ७; १८; ५७, २; ५८, ४; ५९, २; ६१, ५^{२}; **४.** १, ४; ९; १२; १३; २, २०; ३, १२; ४, ५; ५, ३; ४^{२}; ६, १; १०, ४; १२, ६; १६, ७^{२}; १२^{२}; १७, ५; १०; १८, १२; १९, २; ५^{२}; ७; १०; २०, १०^{२}; २१, ४; ७^{२}; २२, ३; ६^{२}; ७; २३, ६; २४, ९; २६, ४^{२}; २९, ३; ३०, ६; १३; ३२, ९; १०; २२; ३३, १; ३४, ३; ३७, २; ३९, ६; ४१, २; ४२, ७; ४५, ७; ५३, ३; ४; ५५, २; ३; ५६, ५; ५८, २; **५.** १, १^{२}; ७–९; २, ८–१०; ४, १; ६; ७, ४; ६; ८; १०, १; ३; १२, १; १५, १; १७, ४; १९, १^{२}; २२, १; २; २९, १०; १३; ३०, ३; ६; ८; ९; ३१, २; ३; ६^{२}; ३३, २; ६; ३६, ४^{२}; ४१, ३–५; ६^{२}; ७; ४२, १; ६; १३; १४^{२}; १६; ४३, ३; ९; ४४, ४; ४५, ५; ४६, २; ७; ४८, २; ४९, ५; ५२, १; ५; ८; १६; ५३, ७; १०; १२; ५४, १; २; ५६, ७; ५८, ६; ५९, १^{२}; ४; ५^{२}; ७; ६०, १; ६४, २; ६५, ३; ६८, १; ७४, ५; ७६, २; ७७, १; ८१, २; ८२, ९; ८३, ४; ६; ८४, १; २; ८५, १; ३; ५; ८६, १; ८७, १^{२}–३^{२}; **६.** ६, १; ५; ८, १; ७; ११, ३; १४, १; १५, १०; १३; १६, ८; २२; ४१; १७, १२; १८, ७; ९; १२; १३; २०, ४; ६^{२}; १०; २१, ९^{२}; २३, ८^{२}; २४, ३; ९; २६, ४; ५^{२}; ३०, १; ३१, ५; ३२, ४; ३६, २; ४०, १; ४१, २; ५^{२}; ४२, ४; ४४, ११; १३; १४; १७; २०; ४५, ४; २४; २५; ४७, ७^{२}; २०; ४९, ४; ८; १२^{२}; १४; ५४, ६; ५७, ५; ५९, १; ९; ६१, ४; १३; ६३, ४^{२}; ५–७; ६६, ९; ६७, २; ४; ९; ६८, ४; ६; ७; ९; ६९, २^{२};

७०, ३; ७२, ३; ७४, १; ४; ७५, १६; **७.** १, ४; ७; २२; २, ४; ४, १; ५, १; ६, १^{२}; ७, १; ६; ११, ३; १३, १; १८, १७; १९; २१; १९, १; ३^{२}; २०, २; ५; २१, २; २४, १; ६; २९, १; ३१, १; ४; १०^{२}; ३३, ३; १४; ३४, १; ५; ९; १८; ३६, १; ४; ८^{२}; ३९, २; ४१, ३^{२}; ४२, १^{२}; ३; ४३, १; २; ५३, १; २; ५६, १४^{२}; ५७, १; ५^{२}; ५८, १–४; ६; ५९, २; ६१, २; ३^{२}; ४; ६; ६२, २; ५; ६४, १; ३; ६६, १; ५; ६७, ९; ६८, २; ३; ७०, १; ५; ७२, ४; ७४, ६; ७५, २; ७६, २; ८०, २; ८२, ६; ८३, ४; ६; ८४, १; ३–५; ८६, १; ४; ८७, १; ८८, १; ३^{२}; ९०, १; ९२, २^{२}; ३; ९३, ४; ९५, १; ९८, ३; ५^{२}; १००, १; ३; ५; ६; १०१, १; १०२, १; १०३, १; ९; १०; १०४, ३; १७; १९; २२; **८.** १, ७; ८; १६; २, १३; १९; ३, १२; ४, ५; १२; १५; ६, २; ७; ८; ९^{२}; ३२^{२}; ७, १; ४; ८, ५; १०; १६; २१; २२; ९, १; १६; १७^{४}; १९; २०^{४}; १०, ३; ४; १२, ८; ९; २३; ३१; ३२; ३३; १३, १४; १५, १; १६, १; १७, ७; ९; १२; १८, २२; १९, २; २७; ३०; २०, ४; २१, ९; १२; १६; २२, ६; २३, १२; २४, १३; २७, ३^{२}; ८; १०; १५; २९, ८; ३१, १७; ३२, १; २७; ३५, ११^{२}; ३६, २; ७; ३७, १^{२}; ३९, ३; ४०, ५; ४४, ३०; ४५, २५; २८; ३१; ४६, १८; २८; ४८, २; ४; ६^{२}; ७; ४९, १; २^{२}; ४; ९; ५०, १; ६; ५१, ८; ५२, ५; ७; ५३, ६; ५६, ४; ५७, ४; ५९, १; ७; ६०, १०; १६; ६१, ९; ६२, २; ६३, ८; ६४, ४; १०; ६६, ८; ११; ६७, ९; ६९, ४; ८; ७१, ६; ७३, ९; ७९, २; ६; ८०, ४; ८१, ५; ६; ८२, १; ५; ८३, ८; ८५, ९; ८८,

५; ८९, ३; ४; ९०, ६; ९३, १६; १९; ९६, ५^{२}; १०; १००, ३; ७; १०१, ३; ५^{२}; १५; १०३, २; ४; ६; ८; **९.** ७, २; ३; १०, १; १२, ६; १३, २; १४, १; १६, १; ४; ५; १७, १; १८, २; २०, १; २१, ७; २२, १; २४, १; ३; २९, १; ३०, १; ४; ३१, १; ३२, १; ३३, १; ३४, १; ३५, ४; ४१, १; ४४, १; ५७, १; ६०, १; ६२, २८; ६३, १६; ६४, ४; ७; १६; १९; ६५, ७; २६; ६६, ७; १३; २८; ६७, १५; २८^{२}; ६८, १; ४; ६९, ९; ७०, ४; ७१, २; ७५, ५; ७६, ३; ७७, १; ७८, १; ७९, १; २; ८१, १; ८२, ४; ८५, ७; १२; ८६, १; २; ४^{२}; १६; १७; ३१; ४२; ४७; ८७, १; ९०, १; ९१, २; ९२, ३; ५; ९३, ३; ५; ९५, ३; ९६, १; ७; २२; ९७, ४; ७; ८^{२}; २३^{२}; ३०; ३१; ३४; ३८; ५२; ९९, २; १०१, १३; १०२, ८; १०३, १; १०४, १; १०६, ४; १०७, १२; १५; १०९, १; १६; १८; ११०, १; २; **१०.** १, २; ७; ४, १^{२}; ५; ८, १; १०, ५; ६; ११, ७; १३, २; १४, ७^{२}; १४^{२}; १५, ७; १२; १६, १; ७; ९; ११; १७, ३; २०, ४; २३, १; २५, ३; ४; ११; २६, १^{२}; ७; २७, ३; ४; १९; २०; २२; २९, २^{२}; ५; ३०, १; ९; ३१, ११; ३२, १; ५; ७; ८; ३३, १; ३५, ५; ३७, ९; ३८, १; ५; ३९, ५; ४०, ११; ४२, १; २; ८; ४३, ४; ४४, ६; ४५, ९; ४६, १; ५; ८^{२}; १०; ४७, ६; ४८, ८–१०; ४९, ४; ७; ८; ११; ५०, ७; ५२, १; ५३, ८; ५४, १; ५६, ५; ५७, १; ५९, १; ५; ६१, १८; ६२, ८; ११; ६६, १०; १२; ६७, ३; ६९, ५; ९; ७०, ९; ७१, १; ७२, १; ८; ९; ७३, ३; ५; ७५, १^{३}; २; ३; ७६, ३; ७७, ३; ६; ७९, ३; ४; ८०, ७; ८३, ७; ८४, १; ३;

८५, १३; १९; २४; २५; २६; ८६, २; ८७, ५; ८; ९; ८८, ११; ८९, १; ४; ८; ९^{४}; ११^{८}; १२; ९०, ७; ९२, ५; ७; ११; १३; ९३, १४^{२}; ९४, १^{२}; ३; ९५, २; १०; १३; १५; ९६, १^{२}; ९; ११; ९७, १०; १३; १४; ९८, ८; ११; १००, १; २; १०१, २; १०२, १; ४; १०३, ७; १२; १३; १०४, ३; १०५, ६; ११; १०६, १; १०७, २; ४; १०८, १; १०९, २; १११, १; ९; ११२, १; २; ८^{२}; ११३, ४; ९; ११४, ६; ७^{२}; ११५, ४; ११६, ९^{२}; ११७, ४; ११९, २; १२०, ६; १२५, ८; १३०, १; १३५, ४^{२}; १३८, ५; १३९, ६; १४१, १; २^{५}; १४२, २^{२}; ४; १४५, ६; १४६, ६; १५०, ५; १६१, १; १६५, ५; १६८, २; १७१, १; १७५, १; १७६, १; २; ३; १७९, २; १८३, १; १८५, ३; १८६, १; १८७, १; १८८, १; २.

प्रऽअध्वने **४.** ५८, ७.

प्रऽअर्पणः **१०.** ४५, ५.

प्रऽअप्यै **१.** ११३, ४.

प्रऽअविता **१.** १२, ८; २३, ६; ८७, ४; **३.** २१, ३; **८.** ९६, २०.

प्रऽअवितारः **८.** २७, २.

प्रऽअवीः **४.** ९, २.

प्रऽअस्यै **१.** १२१, १३.

प्रऽइतिं **१.** ३३, ४.

प्रऽइद्धः **७.** १, ३; **१०.** ६९, १२.

प्रऽइव **१.** १०३, ७; **१०.** १४६, १.

प्रऽइषितः **७.** ७३, ३; **१०.** ३७, ५.

प्रऽइषिताः **१०.** ९८, ६.

प्रऽईखं **७.** ८७, ५.

प्रऽईखे **७.** ८८, ३.

प्रऽउगं **१०.** १३०, ३.

प्रऽऊळ्हः **१.** ११७, १५.

प्रऽकंकृताः **१.** १९१, ७.

प्रकुलऽवित् **७.** १८, १५.

प्रऽकाशः **१०.** १२४, ६.

प्रऽकुपितान् २. १२, २.

प्रऽकेतः **१.** ९४, ५; ११३, १; **३.**

३०, १; ७. ११, १; ३३, १२; १०. १०४, ६; १२९, २.

प्रऽकेतं २. १७, ७.

प्रऽकेतैः ७. ३३, ९; १०. ७, १.

प्रऽक्रीळान् ४. ४१, ११.

प्रऽक्रीळिनः ७. ५६, १६.

प्रऽखादः १. १७८, ४.

प्रऽख्यै ७. ८१, ४.

प्रऽगर्धिनः ४. ४०, ३.

प्रगर्धिनीऽइव १०. १४२, ४.

प्रघ्नताऽइव ९. ६९, २.

प्रऽचक्राणं ९. १५, ७.

प्रऽचर्ता १०. १२४, २.

प्रऽचरन् ५. ४८, ३.

प्रऽचाकशत् ४. ५३, ४.

प्रचेत इति प्रऽचेतः १. २४, १४; ७. १७, ५; १०. ८३, ५; ८७, ९.

प्रऽचेतः ६. १३, ३.

प्रऽचेतयन् ९. ९७, १३.

प्रऽचेतसः १. ४१, १; ४४, ७; ६४, ८; ८४, १२; २. २३, २; ४. ५३, १; ६. ७५, १३; ७. ८७, ३; ८. ७, १२; ४७, ४; ८३, २; ९. ६४, २१; १०. ६३, ८; ६६, १; ८५, १७.

प्रऽचेतसः १. ३९, ९; ५. ८७, ९; ८. ६७, १७; ८३, ५.

प्रऽचेतसं १. ४४, ११; ३. २९, ५; ४. १, $१^{२}$; ७. १६, १२; ८. ८४, २; ९०, ६; १०२, १८; १०. १४०, ५.

प्रऽचेतसा १. १५९, १; ८. १०, ४; १०. ३६, २.

प्रऽचेतसा ५. ७१, २; ८. ९, १५; २०.

प्रऽचेतसे १. ५, ७; ४३, १; ७. ३१, १०; ८. २७, २१.

प्रऽचेताः २. १०, ३; ३. २५, १; ६१, १; ४. ६, २; ६. ५, १; ५; १४, २; ७. ४, ४; १६, ५; १०. ७९, ४; ११०, १; १६४, ४.

प्रऽचेतुने १. २१, ६.

प्रऽचोदयः ८. १२, ३.

प्रऽचोदयन् ३. २७, ७.

प्रऽचोदयन्ता १०. ११०, ७.

प्रऽचोदयात् ३. ६२, १०.

प्रऽच्युवयन्तः १. ८५, ४.

प्रऽच्युतः ९. ८०, ४.

प्रजज्ञिऽवान् ३. २, ११.

प्रऽजज्ञे १०. ७३, १०.

प्रऽजननं ३. २९, १.

प्रऽजया १. २३, २४; ९३, ३; १३६, ६; १०. १८, २; ८०, ३; ८५, २७; ३८; १२८, ५; १६९, ४; १८३, १.

प्रऽजवः ७. ३३, ८.

प्रऽजहितानि ८. १, १३.

प्रऽजा १०. ९५, १८.

प्रऽजाः १. ४३, ९; ६७, ५; ९६, २; ३. ५५, १९; ७. ३३, ७; ८. १०१, १४; ९. ८६, २८; ९७, ४०; १०. ५६, ५; १७०, १; १८३, ३.

प्रऽजातः १. ६९, १.

प्रऽजातं १. १६४, १८.

प्रजानतीऽइव १. १२४, ३.

प्रऽजानन् २. ३, १०; ३. २६, ८; २९, १६; ३१, ५; ३५, ८; ५४, २; ४. १, १०; ७. ४४, ४; १०. १६, ९; १७, ५; ६; ८८, ६; ९१, ४.

प्रजाऽपतिः ४. ५३, २; ९. ५, ९; १०. ८५, ४३; १६९, ४; १८४, १.

प्रऽजाभिः २. ३३, १; ३५, ८; ५. ४, १०; ६. ७०, ३.

प्रऽजाभ्यः २. १३, ४; ४. ५३, ४; ५. ८३, १०; ७. ३५, १०.

प्रऽजां १. १२५, १; १७९, ६; २. ३, ९; ३२, ६; ४१, १७; ४. ३६, ९; ६. ६१, ३; ७. ९६, ६; ८. ६, २; २३; ३५, १०; ५९, ७; ९. ८, ९; १०९, ९; १०. १८, १; ५६, ६; ७; ८५, ४३; १५७, २; १६२, ५; १८३, १.

प्रऽजायाः १. १५९, २; १०. ६१, ९; ९२, १०.

प्रऽजायै ५. ४१, १७; ७. ३६, ९; ५७, ६; ९. १०९, ५; १०. १३, ४; ५४, १; ७२, ९; ७३, ५; १२८, ८.

प्रजाऽवत् १. ११३, १७; १३२, ५; ३. ८, ६; ५. ८२, ४; ६. १६, ३६; ७. ६७, ६; ९. ५९, १; ६०, ४; ८६, ४१; १०. १०४, ४.

प्रजाऽवतः १. २५, ८; ९२, ७; २. २, १२; ३. १६, ३; ६; ८. २३, २७.

प्रजाऽवता १. ७६, ४; ९४, १५.

प्रजाऽवती ८. ३१, ४.

प्रजाऽवतीः ६. २८, १; ७; ५२, १६; ९. २३, ३; ७४, ६; ८६, ४१; १०. १६९, ६.

प्रजाऽवतीषु ७. १, ११.

प्रजाऽवतः १०. ३७, ७; ५७, ६.

प्रजाऽवन्तं ४. ५१, १०; ५३, ७; ७. १, १२.

प्रजाऽवान् ३. ३०, १८; ५४, १८; ५६, ३; ४. २, ५.

प्रऽजासु ८. ५३, ६.

प्रऽजिगतः १. १५०, २.

प्रऽज्ञातारः १०. ७८, २.

प्रणक् १. १८, ३; २. २३, १२; ७. ५६, ९.

प्रऽतताः ३. ३१, २०.

प्रतद्वसू इति प्रतत्ऽवसू ८. १३, २७.

प्रऽतपन् ९. १०८, १२.

प्रऽतरणः १. ९१, १९; २. १, १२; ६. ४७, २६; ७. ५४, २.

प्रऽतरणं ८. ४९, ४.

प्रऽतरणी ५. ४६, १.

प्रऽतरं १. ५३, ११; ९४, ४; १४१, १३; २. ३२, १; ४. १२, ६; ५. ३४, १; ५५, ३; ६. ४७, ७; १०. १०, १; ४२, १; ४५, ९; ५९, १; ६६, १; ७९, ३.

प्रऽतरीता ९. ८६, १९; १०. १००, ५.

प्रऽतवसः १. ८७, १.

प्रऽतवसे ४. ३, ६.

प्रऽतस्थुः १०. ६५, १५.

प्रति १. ९, ४; ११, ६; १२, ५; १९, १; २५, २०; ४१, ८; ४६, १०; १२; ४८, २; १३; ५२, १५; ५४, ७; ५५, १; २; ५७, ४; ६३,

८; ७९, ६; ८८, ६; ९१, ४; ९२, १; ५; ९३, १; ९५, ५; १०१, १०; १०४, ५; १०७, १; ११३, ७; ११५, २; ११६, १५; ११७, २२; ११८, ३; ७; ८; ११९, २; ९; १२१, ९; १२४, ३; १२७, १०; १४४, ७; १५१, १; १५५, ६; १६१, ३; १६२, १५; १६४, २४; २९; १६५, ४; १२; १६८, ८; १६९, ६; ७; १७१, १; १८०, ४; १८३, ६; १८४, ६; १९१, ५; **२.** १, ८; १५; ३, २^{२}; ११, २१; १५, ७; १०; १६, ९; १७, २; ९; १८, ९; १९, ९; २०, ८; ९; २४, ११; ३३, १२; ३६, ४; ३९, ३; **३.** १, १७; ४, ५; ५, १; १८, १; २१, ५; ३०, १७; ३१, ४; ३३, ८; ३६, २; ५२, ८; ५३, ३; ५८, २; **४.** ३, ८; १४; ४, ३–५; १५; १२, २; १३, १; १७, ७; १९, ३; २४, ७; २७, ५^{२}; ४५, ५; ५२, १; ४; ५; ५३, २; **५.** १, १; २, ११; २९, ४; ३०, १२; १५; ४१, १८; ४२, २; ४४, १२; ४८, ४; ४९, २; ५५, ६; ५७, १; ६१, ९; ७५, १^{२}; ७६, २; ८०, १; ८१, २; ८३, ९; ८४, २; ८६, ३; **६.** ३, ५; ६; १३, ४; २५, ५; ३०, १; ४२, १; ४७, २२; २८; ६८, १०; **७.** १, १८; ३, ६; ९, ४; १५, १३; २८, ४; ३१, ६; ३४, २१; ४०, १; ५४, १^{२}; २; ५९, ८; ६२, २; ६३, ५; ६५, ४; ६७, १; ७०, ५; ७३, ३; ७५, ६; ७; ७६, ६; ७८, १; २^{२}; ३; ५; ८०, १; ८१, १; ३; ९५, ५; १०१, ३; १०४, ७; ११; २५; **८.** ३, २३; ५, ३; २०, ९; १६; २१, ११; २३, १३; २२; ३१, ६; ३२, ४; ४४, २; ११; ४५, ५; ५६, १; ६४, २; ७०, २; ८२, १; ९२, २२; ९६, ९; १९; ९९, ३; १००, ५; १०१, ७; १०; १३; **९.** ६९, १; ४; ९२, १; १००, ९; ११३, ३; **१०.** १, ४^{२}; १३, ३; १६, ३; २७, ११; १३; ३०, १३; ३७, ७; ८; ४०, १; ४८, ७; ६२, १; ६४, १३; ७०, १; ८७, ४; १०; १२; २०; २३; २४; २५^{२}; ९५, १३; ९७, ३; ९८, १; २; १०१, १०; १०५, ११; ११४, ९; ११६, ७; ८; ११८, २; ८; ११९, ७; १२२, २; १३३, ७; १४२, ५; १४९, ५; १६७, ४; १७२, ३; १८९, ३.

प्रतिऽआधिः **१०.** २६, ५.

प्रतिऽआधि **१०.** १, ५.

प्रतिऽअर्हन् **१.** ३२, १२.

प्रतिऽआवर्तय **६.** ४७, ३१.

प्रतिऽइतये **१.** ३६, २०.

प्रतिऽइत्यै **१०.** ११६, ५.

प्रतिऽइष्यं **१०.** १२९, ४.

प्रतिऽईपं **७.** ८९, ३; **१०.** २८, ४.

प्रतिऽएतन **६.** ४२, २.

प्रतिऽकामं **३.** ४८, १; **१०.** १५, ८; ११२, १.

प्रतिऽक्षियंतं **२.** १०, ४.

प्रतिऽगृह्य **१.** १२५, १.

प्रतिऽघ्नंति **८.** २५, १५.

प्रतिऽचक्षणाय **६.** ४७, १८.

प्रतिऽचक्षाणः **९.** ८५, १२.

प्रतिऽचक्ष्य **२.** २४, ६; ७.

प्रतिचक्ष्यंऽइव **१.** १२४, ८.

प्रतिऽचक्ष्या **१.** ११३, ११.

प्रतिऽच्यवीयसी **१०.** ८६, ६.

प्रतिऽजन्यानि **४.** ५०, ७; ९.

प्रतिऽजानते **३.** ४५, ४.

प्रतिजूतिऽवर्पसः **३.** ६०, १.

प्रतिऽदीप्नें **१०.** ३४, ६.

प्रतिऽदोषं **१.** ३५, १०; **६.** ७१, ४.

प्रतिऽधर्यः **१०.** ८५, ८.

प्रतिऽधा **८.** ७७, ४.

प्रतिऽधातवे **१.** २४, ८.

प्रतिऽधीयमानं **१.** १५५, २.

प्रतिऽधृषे **८.** ६०, १३; १४.

प्रतिऽनुदन् **१०.** १२८, ६.

प्रतिऽपीयंति **१०.** २८, ११.

प्रतिऽबुद्धाः **१.** १९१, ५.

प्रतिऽबुध्यमानाः **४.** ५१, १०.

प्रतिऽभूषतः **८.** ६२, ५.

प्रतिऽभूषंति **६.** ५२, ८.

प्रतिऽभूषथ **६.** ४२, ३.

प्रतिऽभूषेम **१०.** १००, ३.

प्रतिऽभृतस्य **४.** २०, ४; **७.** ९१, ६; **१०.** ९६, १२.

प्रतिऽभृता **७.** ६८, १.

प्रतिऽमा **१०.** १३०, ३.

प्रतिऽमानं **१.** ३२, ७; ५२, १२; १३; १०२, ६; ८; **२.** १२, ९; **३.** ३१, ८; **४.** १८, ४; **६.** १८, १२; **१०.** १११, ५; १३८, ३.

प्रतिऽमानानि **१०.** ८९, ५; १२०, ६.

प्रतिऽमै **३.** ६०, ४.

प्रतिऽयंतं **८.** ६७, १७.

प्रऽतिरन् **१.** ४४, ६; **९.** ८०, २; ९६, १४.

प्रऽतिरंती **७.** ७७, ५.

प्रऽतिरंते **१.** ११३, १६; **८.** ४८, ११.

प्रऽतिरंतौ **८.** १०१, ८.

प्रऽतिरे **८.** ४८, १०.

प्रतिऽरूपः **६.** ४७, १८.

प्रतिऽलोभयंती **१०.** १०३, १२.

प्रतिऽवेदयन् **१.** १६२, ४.

प्रतिऽवेशं **१०.** ६६, १३.

प्रतिऽशिक्षंति **१०.** २९, ५.

प्रतिऽस्कभे **१.** ३९, २.

प्रतिऽस्तुतिं **८.** १३, ३३.

प्रतिऽस्था **१०.** ७३, ६.

प्रतिऽस्थां **५.** ४७, ७; **१०.** १०६, ९.

प्रतिऽस्थिः **६.** १८, १२.

प्रतिऽहर्यते **८.** ४३, २; १७.

प्रतिऽहर्यथ **१.** ४०, ६.

प्रतिऽहिताभिः **१०.** १०३, ३.

प्रतिऽह्वरे **७.** ६६, १४.

प्रतीकं **६.** ५०, ८; ७५, १; **७.** ३, ६; ८, १; ३६, १; **१०.** ८८, १९; ११८, ३.

प्रतीकेन **१०.** ११८, ८.

प्रतीचः **१.** १७३, ५; **३.** ३०, ६; **१०.** ८७, ४.

प्रतीची १. ९२, ९; १२४, ७; ३. ६१, ३; ५. ८०, ६; ७. ३९, १; ७६, २; ७७, २; ८. ४६, ३३.

प्रतीची इति १. ९५, ५; ९. ६६, २.

प्रतीचीः ३. १८, १; ४. ३, २.

प्रतीचीनः १०. ८३, ६; ९८, २.

प्रतीचीनं ३. ५५, ८.

प्रतीचीनं ५. ४४, १.

प्रतीचीने १०. १८, १४.

प्रतीचीं १०. १८, १४.

प्रतीचीं ५. १२, १.

प्रतीत्यं ७. ६८, ६.

प्रतीत्येन ४. ५, १४.

प्रतीव्यं ८. २३, १; २६, ८; ३९, ५.

प्रऽतूर्तयः ८. १३, २९.

प्रऽतूर्तये १. १२९, २.

प्रऽतूर्तिषु ८. ९९, ५.

प्रऽतूर्वैतः ५. ६५, ४.

प्रऽतुदः ७. ३३, १४.

प्रत्न ६. ३९, ५; १०. ४, १.

प्रत्नः १. ११७, १; २. ७, ६; ६. ६२, ४, ८. ११, १०; ९. ७३, ३.

प्रत्नऽथा १. ९६, १; १३२, ३; २. १७, १; ३. २, १२; ५. ८, ५; ४४, १; ६. १७, ३; ८. ६३, ४.

प्रत्नं १. ३६, ४; ३. ९, ८; ४२, ९; ५. ८, १; ६. १८, ५; २२, ७; ४५, १९; ८. २३, २०; २५; ४४, ७; ९. ६, ८; ४२, ४; ८६, १४; १०७, ५; १०. ७, ५; ५५, २; ८८, १३.

प्रत्नऽवत् १. १२४, ९; ६. १६, २१; २२, ७; ६५, ६; ८. १३, ७; ९. ९, ८; ४९, ५; ९१, ५.

प्रत्नस्य १. ३०, ९; ८७, ५; ३. ३१, १०; ३८, ९; ५८, १; ८. ६, ३०.

प्रत्ना १. १०५, ५; ६. २१, ६; ६२, ५.

प्रत्नाः ९. १, ६.

प्रत्नात् ९. ७३, ६.

प्रत्नानि १. १०८, ५.

प्रत्नाभिः ८. १३, २४.

प्रत्नां ८. ९५, ५; ९. ५४, १.

प्रत्नाय १. ६१, २; १०. ९१, १३.

प्रत्नासः ४. २, १६; ५०, १; ५. ८, १; ६. २१, ५; ९. २३, २; ९८, ११.

प्रत्ने इति ६. १७, ७.

प्रत्नेन ६. २१, ७; ८. ६, ११; ४४, १२; ७६, ६; ९. ३, ९; ४२, २; ९७, ४७.

प्रत्नेभिः ९. ५२, २; १०. ३, ६.

प्रत्नेषु ८. १३, २०.

प्रत्यक् १०. ८७, १५.

प्रत्यङ् १. ५०, ५[३]; १४४, ७; २. ३, १; ५. २८, १; ९. ८०, ३; १०. १२, १; ७९, ५; ८८, १६; १२३, ७; १४१, १.

प्रत्यंचः १०. १२८, ६.

प्रत्यंचं २. १०, ५; ७. १२, १; १०. २७, १३; २८, ४; ९; ८७, १७; १५७, ५.

प्रऽत्वक्षसः १. ८७, १; ५. ५७, ४.

प्रऽत्वक्षसं १०. ४४, ३.

प्रऽत्वक्षाणः १०. ४४, १.

प्रथः १०. १८१, १.

प्रथतां १०. ७०, ४.

प्रथते १०. ९४, ९.

प्रथते १. १२४, ५.

प्रथंत ९. ९४, २.

प्रथंतां २. ३, ५.

प्रथमः १. ३१, १–३; ८३, १; ५; १०१, ५; १३४, ६; १६२, ४; १६३, २; ९; २. १०, १; १२, १; २५, ४; २७, १२; ३०, १; ३६, १; ३. २१, १; ४. १, ११; ७, १; ३८, ६; ५. ३१, १; ४३, ३; ६. १, १; ९, ४; १५, १६; ४१, १; ५४, ४; ७. ११, १; ४४, ४; ८. २३, १८; २७, ८; ६१, २; ९०, २; ९. ८६, २८; ८९, ३; ९१, १; १०७, २३; १०. ८, २; ११, २; १२, २; १४, २; ३४, १२; ८५, ४०; ८८, ४; १०७, ५[२]; ६; १०९, २; १२२, ५; १६७, ४.

प्रथमऽछत् १०. ८१, १.

प्रथमऽजाः १. १६४, ३७; ३. २९, १५; ६. ७३, १; १०. ५, ७; ६१, १९; १०९, १; १६८, ३.

प्रथमऽजां १. ३२, ३; ४.

प्रथमऽभाजं ६. ४९, ९.

प्रथमं १. ३१, ११; ३५, १; ७७, ३; ८३, ४; ९६, ३; १०२, ९; १०८, ६; १४४, १; १४५, २; १६३, १; १६४, ४; १८५, १०; २. १३, १–४; १७, ३; १८, २; २२, ४; २४, १०; ३९, ३; ३. ४, ३; २९, ५; ४८, १; ४. १, १२; १६; ११, ५; १७, ७; ५०, ४; ५४, २; ५. ११, २; ४२, ७; ६. १, २; ७. ४४, १; ४७, १; ९७, १; ८. ३, ११; २३, २२; ७१, १२; ८०, ५; ९. ६८, ५; ७०, ६; ८६, १५; १०. ४५, १; ४६, ९; ५३, ४; ६४, १३; ६७, २; ७१, १; ७५, ६; ८२, ५; ८८, ८; १२९, ४; १८१, ३.

प्रथमश्रवःऽतमः ४. ३६, ५.

प्रथमस्य १. २४, २; १२३, ९; ३. १५, ४; ६. २८, ५; १०. १०, ६; ९४, ८.

प्रथमा १. ११३, ८; १५; १२३, २; ५; १२४, २; १५१, ८; १५२, ३; १८८, ७; २. ३, ७; ३. ४, ७; १७, १; ३१, ६; ३६, ८; ५६, १; ४. ४२, २; ५. ७७, १; ७. ७६, ६; ९८, ५; १०. ३५, ४; ५५, ४; ५६, ३; ८३, ७; ११२, ८; १२५, ३.

प्रथमाः १. १५२, २; २. ३४, १२; ३. ३६, ३; ४. २, १५; ७. ७८, १; ८०, १; ९. ७९, ५; ८६, ३०; ११०, ७; १०. २७, २३; ४२, १०; ४४, ६; १०९, १; १११, ८.

प्रथमान् १०. १७, ११.

प्रथमानि १. ३२, १; १६४, ४३; ५०; १६६, ७; ६. ७२, १; ८. १०३, ६; १०. ९०, १६; ११३, ७.

प्रथमां १०. ६३, ७.

प्रथमाय २. १७, २; १०. १४७, १.

प्रथमासः १०. ६, ७.

प्रथमे ८. १३, २; ९. ९७, ४०; १०. ७२, ३.

प्रथमे इतिं १०. १२, १.
प्रथयत् ४. ४२, ४.
प्रथयंन् ३. १४, ४; ४. ५३, २; ८. १२, ६; ५१, ८.
प्रथयंतः ५. ४३, ७.
प्रथयंतं १०. ४९, ६.
प्रथयसे १०. २१, ८.
प्रथयस्व १०. १४०, ४.
प्रथंसः १०. ८९, ११.
प्रथस्व ५. ५, ४.
प्रथाना १. ९२, १२.
प्रथानां ६. ६४, ३.
प्रथिना १. ८, ५; ८. ५६, १.
प्रथिंष्ट ५. ५८, ७; १०. ६१, ५.
प्रथिंष्टं १०. ८७, १.
प्रऽदक्षिणित् २. ४२, १; ३. १९, २; ३२, १५; ४. ६, ३; ५. ६०, १; १०. २२, १४.
प्रऽददातु ७. १०४, ९.
प्रऽदिवंः १. ५३, २; १४१, ३; २. ३, १; ३. ३६, २; ३८, ५; ४३, १; ४७, १; ५०, २; ५१, ४; ४. ६, ४; ७, ८; ३४, ३; ५. ८, ७; ६. ५, ३; २३, ५; ४४, १२; ६२, ८; ७. ९०, ४; ९. ७२, ४; १०. ५, ४; ३७, ३.
प्रऽदिवां ५. ६०, ८.
प्रऽदिविं २. १९, १; ३६, ५; ३. ४६, ४; ५. ६२, ४; ७६, ४; ६. २१, ८; ४१, ३; ७. ९८, २.
प्रऽदिशंः १. १६४, ४२; ६. ७५, २; ७. ३५, ८; ८. १००, ४; ९. ८६, २९; १०. १९, ८; ५१, ९; ५६, ७; ५८, ४; १२१, ४; १२८, १.
प्रऽदिशं २. ४२, २; ९. १११, ३.
प्रऽदिशां १. १०१, ७; १६४, ३६; १०. ११०, ४; ७.
प्रऽदिशिं २. १२, ७; १०. ११०, ११.
प्रऽदिष्टाः ३. ३०, १२.
प्रऽदीदयत् ८. ६, २४.
प्रऽदीध्याना १. ११३, १०.
प्रऽद्रुसिः ६. ३, २.
प्रऽद्वेदिंशात् १०. १०२, १०.
प्रऽदोधुंवत् २. ११, १७.
प्रऽदोषं १. १९१, ५.
प्रऽधनंस्य १. १६९, २.
प्रऽधनें १. ११६, २; १०. १०२, ५.
प्रऽधनेंषु १०. १५४, ३.
प्रऽधन्यासु १०. ९९, ४.
प्रऽधयंः १. १६४, ४८.
प्रऽधावंति १०. १५४, १.
प्रऽधिं १०. १०२, ७; १३८, ६.
प्रधी इवेतिं प्रधीऽइंव २. ३९, ४.
प्रधीन्ऽइंव ४. ३०, १५.
प्रनंपादिति प्रऽनंपात् ८. १७, १३.
प्रऽनयंन्त १०. ४, ५.
प्रऽनयंसि १. १२९, १.
प्रऽनिनायं ३. ८, ११.
प्रऽनींतं १. ११७, १७.
प्रऽनींतयः ६. ४५, ३.
प्रऽनींतिः ६. ४८, २०; ८. ६८, ११; १०. ६९, १.
प्रनींतिऽभिः १०. १०४, ५.
प्रऽनींतिषु १. ११४, २; ८. ६, २२.
प्रऽनींती १. ९१, १; ३. ५१, ७; ४. ४, १४; ७. २८, ३; ३२, १५.
प्रऽनींतौ २. २७, ५; १३; ३. १५, १.
प्रनेंतरिति प्रऽनेंतः ७. ४१, ३.
प्रनेतरिति प्रऽनेतः २. २८, ३; ३. ३०, १८; ८. २४, ७; ४६, १.
प्रऽनेता २. ९, २; ३. २३, १; ८. १९, ३७.
प्रऽनेतारंः १. १६९, ५; ५. ६१, १५; ७. ५७, २.
प्रऽनेतारं ८. १६, १०.
प्रऽनेनीः ६. २३, ३.
प्रऽनेषंत् २. २०, ३.
प्रऽनोदं १०. १६५, ५.
प्रऽन्यंः ३. ३८, २.
प्रऽपतेंत् १०. ९५, १४.
प्रऽपथिन् ६. ३१, ५.
प्रपथिन्ऽतंमं १. १७३, ७.
प्रऽपंथी ८. १, ३०.
प्रऽपंथे १०. १७, ४; ६[१]; ६३, १६.
प्रऽपंथेषु १. १६६, ९.
प्रऽपंदाभ्यां १०. १६३, ४.
प्रऽपंदैः ६. ७५, ७.
प्रऽपश्यंतः १०. १२०, ५.
प्रऽपश्यंमानः १०. १२४, २.
प्रऽपा १०. ४, १.
प्रऽपित्वं ३. ५३, २४; ५. ३१, ७.
प्रऽपित्वात् १०. ७३, २.
प्रऽपित्वे १. १०४, १; १३०, ९; १८९, ७; ४. १६, १२; ६. ३१, ३; ७. ४१, ४; ८. १, २९; ४, ३.
प्रऽपिबंति १०. ८५, ५.
प्रऽपिबंते १०. ११४, ७.
प्रऽपींताः ७. ४१, ७.
प्रऽपृंचती १. २, ३.
प्रऽप्रं १. ४०, ७; १२९, ८; १३८, १; १५०, ३; ३. ९, ३; ५. ५, ५; ५८, ५; ६. ४८, १; ७. ६, ३; ८, ४; ८. ६९, १; ९. ९, २.
प्रऽप्रुथ्यं ३. ३२, १.
प्रऽफर्व्यं १०. ८५, २२.
प्रऽबांधिता १०. १०८, ९.
प्रऽबावंधाना ७. ९५, १.
प्रऽबुधां १०. १२८, ६.
प्रऽबुधिं ८. २७, १९.
प्रऽबोधयंती १. ११३, १४; ४. १४, ३.
प्रऽबोधयंतीः ४. ५१, ५.
प्रऽब्रुवाणः १. ५५, ४; २. ४२, १; १०. ५४, २.
प्रऽब्रुवाणा १०. ६५, ६.
प्रऽभंगं ८. ४६, १९.
प्रऽभंगी ८. ६१, १८.
प्रऽभंजन् १०. १०३, ४.
प्रऽभंर्ता १. १७८, ३; ८. २, ३५.
प्रऽभंर्तुं ३. ४८, १.
प्रऽभंर्मणि १. ७९, ७; ८. ८२, १.
प्रऽभुवः २. ३८, ५.
प्रऽभवंतं २. १३, ४.
प्रऽभासिं १. १२१, ७.
प्रऽभु १. ९, ५; २. २४, १०.
प्रऽभुः १. १८८, ९; ८. ११, ८; ४३, २१; ९. ८३, १.
प्रऽभुंजती १. ४८, ५.
प्रऽभुं ७. ८२, ३.
प्रभुवसो इतिं प्रभुऽवसो १. ५७, ४; ७. २२, २; ८. ४५, ३६; ९. २९, ३.

प्रभुऽवसोः ९. ३५, ६.
प्रऽभूतः ८. ५८, २.
प्रऽभूतये ८. ४१, १.
प्रऽभूता ७. ७७, ३.
प्रऽभूती ४. ५४, ३.
प्रभूती इति प्रऽभूती ४. ४१, ७.
प्रऽभूतौ ३. १९, ३.
प्रऽभूषणि १०. १३२, १.
प्रऽभूषतः १. १५९, १; ९. २९, १.
प्रऽभूषन् ३. ५५, १.
प्रऽभृतः १. १६५, ४.
प्रऽभृतं १. १६२, ८; ७. ९१, ५.
प्रऽभृतस्य १. १४७, २; १०. ११६, ४.
प्रऽभृता ५. ३२, ५; १०. १२०, २.
प्रऽभृताः १. ५१, १२.
प्रऽभृतिं २. २४, १; ३. ३६, १.
प्रऽभृतौ ५. ३२, ७; ७. ३८, २.
प्रऽभृथस्य ५. ४१, १९.
प्रऽभृथे २. ३४, ११; ५. ४१, ४; ७. ४०, ५.
प्रऽभृथेषु १. १२२, १२; ५. ३३, ५.
प्रऽभोः ९. ८६, ५.
प्रऽभ्वीः १. १८८, ५.
प्रऽमगंदस्य ३. ५३, १४.
प्रऽमतिः १. ३१, ९; १०; १४; १६; ९४, १; १०९, १; २. २९, २; ६. ४५, ४; ७. २९, ४; १०. १००, ५; ११.
प्रऽमतिं १. ३३, १; ७१, ७; ३. ५७, ६; ४. १६, १८; ७. ९३, ३; ४; ८. १९, २९; १०. २३, ७.
प्रऽमत्या १. ५३, ५.
प्रऽमंदुः ७. ३३, १.
प्रऽममर्षे ८. ४५, १५.
प्रऽमरस्य १०. २७, २०.
प्रऽमहसः ५. २८, ४.
प्रऽमहसा ७. ६६, २; ८. २५, ३.
प्रऽमा १०. १३०, ३.
प्रऽमादे ८. २, १८.
प्रऽमिनतः ४. ३, १३.
प्रऽमिनती १. ९२, ११; १२४, २.
प्रऽमिनंति १. २४, ६.
प्रऽमिनाति ७. ६३, ३.
प्रऽमिनानः १०. २७, १९.
प्रऽमिनामं ८. ४८, ९; १०. २, ४.
प्रऽमियं ४. ५५, ७.
प्रऽमियै ४. ५४, ४.
प्रऽमीयसे ५. ७९, १०.
प्रऽमुंचन् १. १४०, ८.
प्रऽमुदः ९. ११३, ११; १०. १०, १२.
प्रऽमृणः १०. १०३, ४.
प्रऽमृणन् ३. ३०, ६; १०. ८४, ३.
प्रऽमृणंतं १०. १०३, ६.
प्रऽमृषे ३. ९, २.
प्रऽमे ९. ७०, ४.
प्रयः १. ३१, ७; ४५, ८; ६१, १; ११८, ४; ११९, १; १३२, ३; १३४, १; २. ३७, ४; ४. १५, २; ४६, ३; ५. ५१, ५–७; ६. ६३, ७; ८. ६, ४२; १३, २८; १९, २२; ३२, २९; ७४, १४.
प्रयःऽइव १. ६१, २.
प्रयःऽभिः १. २, ४; ९. ९२, १.
प्रयक्षऽतमं १. ६२, ६.
प्रऽयक्षन् २. ५, १.
प्रऽयक्षे ३. ७, १; ३१, ३.
प्रऽयच्छंसि ८. १७, १०.
प्रऽयज्यवः ५. ५५, १.
प्रऽयज्युवः १. ३९, ९; ८६, ७; ६. ४८, २०; ७. ५६, १४.
प्रऽयज्यवे ५. ८७, १.
प्रऽयज्यून् ८. ७, ३३.
प्रयज्यो इति प्रऽयज्यो ३. ६, २; ६. २१, १०; २२, ११; ४९, ४.
प्रऽयज्योः १. १८०, २.
प्रयतऽदक्षिणं १. ३१, १५; ६. ५३, २.
प्रयतऽदक्षिणासः १०. १०७, ३.
प्रऽयतं १. १५४, ३; ३. ३५, १०; ४. २७, ५.
प्रऽयतस्य ४. ५, १०; ७. ९८, ६.
प्रऽयता ४. १५, ८; ५. ३०, १२; ३४, ४; ४२, ३; ८. ६०, १; १०. १५, १२.
प्रऽयताः ५. ३३, १०.
प्रऽयतान् १. १२६, २.
प्रऽयतानि १०. १५, ११.
प्रऽयतासु १. १६६, ४.
प्रऽयति १. १६, ३; ३. २९, १६; ५. २८, ६; ६. १०, १; ८. ३, ५; ७, ६; १३, ३०; ७१, १२; १०. २१, ६.
प्रऽयतिः १०. १२९, ५.
प्रऽयतिं १. १२६, ५.
प्रऽयती १. १०९, २.
प्रऽयुती १०. ८५, १२.
प्रऽयन् १०. १८९, १.
प्रऽयंतः १. ७६, ४.
प्रऽयंते १. १५२, ४.
प्रऽयंता १. ५१, १४; ७. १९, १; ८. ९३, २१; ९. ४६, ५.
प्रऽयंतारा ४. २१, ९.
प्रऽयंति १०. १०७, ९.
प्रऽयुम्यमानान् ३. ३६, २.
प्रऽयुवयन् ३. ४८, ३.
प्रयसाः २. १९, १.
प्रयसा १. ५८, ७; ७१, ३; ३. ५४, ३; ४. ५, ६; ८. ६०, १२.
प्रयसे ५. ६६, १; ९. ६६, २३.
प्रऽयस्ता ३. ५३, २२.
प्रयस्वतीः ३. ६, ३.
प्रयस्वंतः १. ६०, ३; १३०, १; ३. ५२, ६; ५. २०, ३; ६. १६, ३७; ७. ९४, ६; ८. ६५, ६; ९. ४६, ३; १०. ७७, ४; ११६, ८.
प्रयस्वान् ३. ५९, २; ४. ४१, २; ७. ७३, २; ८५, ४; ९. ६६, २३; १०. ४२, ५.
प्रयांसि १. ८६, ७; १३५, ४; १६९, ३; २. १९, २; ३. ११, ७; १२, ८; ३०, १; ६. १५, १५; १६, ४४; ८. ६०, ४; ९. ८७, ६; १०७, २५; १०. ५३, २; ९१, ९.
प्रऽयाः ३. २९, १५.
प्रऽयाजाः १०. ५१, ९.
प्रऽयाजान् १०. ५१, ८.
प्रऽयाजे १०. १८२, २.
प्रऽयाथने ८. २७, ६.
प्रऽयाने ४. ४६, ७; ५. ४९, २; ८१, २; ३.
प्रऽयानें ८. ४३, ६.

प्रऽयामनि १. ११९, २.
प्रयियोः ८. १९, ३७.
प्रऽयुक्ति ६. ११, १; १०. ३०, १.
प्रऽयुक्तिः १. १५३, २.
प्रऽयुक्तिषु १. १५१, ८.
प्रऽयुच्छंतः १०. ६५, ५.
प्रऽयुजः १. १८६, ९; ८. ३७, ५; १०. ३३, १; ७७, ५; ९६, १२.
प्रऽयुंजती ५. ४७, १.
प्रऽयुतः ३. ५५, ४.
प्रऽयुत ५. ३२, २.
प्रऽयुताः १०. २७, ८.
प्रऽयुतां ३. ५७, १.
प्रऽयुती १०. ३७, १२.
प्रऽयुधः ५. ५९, ५.
प्रऽयै १. १४२, ६; १०. १०४, २.
प्रऽयोगं १०. ७, ५.
प्रऽयोता ७. ८६, ६.
प्रऽराजसि ८. ६, २६.
प्रऽराध्यं ५. ३९, ३.
प्रऽरिक्ता १. १००, १५.
प्रऽरेके ३. ३०, १९.
प्रऽरेचनं १. १७, ६.
प्रऽरोचयन् ९. ७५, ४.
प्रऽवक्ष्यामः १. १६२, १.
प्रवणे १. ५२, ५; ६; ५७, १; १०४, ३; ११९, ३; ५. ४४, ४; ६. ४६, १४; ८. १०३, ११; ९. ६९, ७; १०. ४३, ३.
प्रवणेभिः ३. २२, ४.
प्रवणेषु १. ५४, १०.
प्रऽवत् ९. ७४, ७; १०. १४२, २.
प्रऽवतः १. १४४, ५; ४. १७, ७; १९, ३; २२, ४; ६. १७, १२; ४७, १४; ७. ३२, २७; ३७, ५; ५०, ४; ९. २२, ६; ५४, २; १०. १४, १; ५८, ६.
प्रऽवति ५. ३१, १.
प्रऽवता १. ३५, ३; १७७, ३; ३. ५, ८; ३०, ६; ४. ३१, ५; ८. ६, ३४; १३, ८; ९. ६, ४; २४, २; १०. ४, ३; ७५, २.
प्रवताऽइव ४. ३८, ३.
प्रऽवतां २. १३, २; १०. ७५, ४.
प्रवत्ऽभिः १. ३३, ६.
प्रवत्ऽभ्यः ५. ५४, ९.
प्रवत्ऽयामना १. ११८, ३.
प्रवत्वति ५. ८४, १.
प्रवत्वती ५. ५४, ९.
प्रवत्वतीः ५. ५४, ९.
प्रवत्वतीभिः ८. १३, १७.
प्रवत्वंतः ५. ५४, ९.
प्रवत्वान् १. १८१, ३.
प्रवत्ऽसु ६. ४७, ४.
प्रवंत ४. ५८, ८.
प्रऽवंतवे १. १३१, ५.
प्रऽवपंतं १०. ११५, ३.
प्रऽवयाः २. १७, ४.
प्रऽवर्तमानकः १. १९१, १६.
प्रऽवसथानि २. २८, ७.
प्रऽवहंतः १०. ९४, ६.
प्रऽवहंति १०. १७, १०.
प्रवा १. ३४, ८.
प्रऽवाचनं ४. ३६, १; १०. ३५, ८.
प्रऽवाचे ९. ९५, २.
प्रऽवाच्यः ४. ३६, ५.
प्रऽवाच्यं १. १०५, १०; १६; ११७, ८; १३२, ४; १५१, ३; २. २२, ४; ३. ३३, ७; ४. ५, ८; ८. ६२, ३.
प्रऽवाच्या १. ५१, १३; ४. २२, ५; १०. ३९, ४.
प्रवातेऽजाः १०. ३४, १.
प्रवासः १०. ७७, ५.
प्रवासाऽइव ८. २९, ८.
प्रऽविक्ताः ७. ८५, ३.
प्रऽविक्ते ६. ५०, ५.
प्रऽविदा ३. ७, ६.
प्रऽविद्धं १. १८२, ६.
प्रऽविद्म १०. १५, १३.
प्रऽविद्वान् १. १४७, ५; ७. ३३, १२; १०. २, ७.
प्रऽविवेश १०. १६, १०.
प्रऽविवेशिथ १०. ५१, १.
प्रऽविष्टः ७. ४९, ४.
प्रऽविष्टं १०. ५१, २.
प्रऽविष्टां १०. ७१, ३.
प्रऽवीता ३. २९, ३.
प्रऽवीरः १०. १०३, ५.
प्रऽवृक्तं १. ११६, २४.
प्रऽवृजे ५. ३०, १५.
प्रऽवृण्वंतः ९. २१, २.
प्रऽवृत् ३. ३१, ३.
प्रऽवृद्ध १. ३३, ३; १६५, ९; ८. ३३; १२, ८; ९३, ५.
प्रऽवृद्धः ४. १८, १; ८. ७७, ३; ९६, २.
प्रऽवेदं १०. ७१, ६.
प्रऽवेपनी ५. ३४, ८.
प्रऽवोचति ५. २७, ४.
प्रऽवोळ्हुं १०. २, ३.
प्रऽवोळ्हॄन् २. १५, ४.
प्रऽव्राजे ७. ६०, ७.
प्रऽशंसति ८. ७४, २.
प्रऽशंसमानः ८. १९, ८.
प्रऽशंसात् ४. २, ८.
प्रऽशंस्यः २. २, ११; ८. १९, ९.
प्रऽशंस्यं २. २, ३.
प्रऽशर्धे ८. ४, १.
प्रऽशस्त १. ३६, ९.
प्रऽशस्तः १. १८०, ८.
प्रऽशस्तः १. ६६, २; २. २७, १२.
प्रऽशस्तं १. ६०, १; ७. १, १; ५; ९०, २; ८. ८०, १०; १०. ९१, १५; १६०, ३.
प्रऽशस्तयः १. २६, ९; ६. ४५, ३; ८. १९, १९; ४०, ९; ४५, ३३; ९. २, ८.
प्रऽशस्तये १. २१, ३; २३, १९; ७४, ६; १२२, ११; १७४, ४; ४. ५६, ५; ५. ३९, ४; ८. १२, १५; ९. ७०, ६.
प्रऽशस्ता ५. ६८, २; ७. ८४, ३.
प्रऽशस्तां ७. १, १०.
प्रऽशस्तिः ८. ६, २२.
प्रशस्तिऽकृत् १. ११३, १९.
प्रशस्तिऽभिः १. १४८, ३; ५. ९, ६; १६, १; ६. १५, २; ८. १९, २९; ४१, २; ७४, २; ९. १०, ३.
प्रऽशस्तिं १. ७०, ५; १८१, १; २.

११, १२; ४१, १६; ५. ५७, ७;
७. ६, १; २२, ३.
प्रऽशस्यः ८. ११, २.
प्रऽशस्यते २. ८, ३.
प्रऽशासत् १. ९५, ३.
प्रऽशासनं ८. ७२, १.
प्रऽशासने १. ११२, ३.
प्रऽशास्ता १. ९४, ६; २. ५, ४.
प्रऽशास्त्रं २. १, २.
प्रऽशास्त्रात् २. ३६, ६.
प्रऽशिषः १. १४५, १; ९. ८६, ३२.
प्रऽशिषं ९. ६६, ६; १०. १२१, २.
प्रऽश्रवसः ५. ४१, १६.
प्रष्टिः १. ३९, ६; ८. ७, २८.
प्रष्टिऽभिः १. १००, १७.
प्रष्टिऽमतः ६. ४७, २४.
प्रष्टुं १. १६४, ४.
प्रऽसक्षत् ४. १२, १.
प्रऽसक्षिणः ८. ४९, ८.
प्रऽसक्षिणा ८. १३, १०.
प्रऽसक्षिणे ८. ३२, २७.
प्रऽसत्तः ५. ६०, १.
प्रऽसत्ता ६. ६२, १.
प्रऽसर्गे १. १२१, ४.
प्रऽसर्गे ७. १०३, ४.
प्रऽसर्तवे ८. ६७, १२.
प्रऽसर्पणे १०. ६०, ७.
प्रऽसर्पथ १०. ९७, १२.
प्रऽसस्राणः ५. ४४, ३.
प्रऽसस्राणस्य ५. १२, ६.
प्रऽसस्रे २. ३५, ५.
प्रऽसवः ३. ३३, ४; ११.
प्रऽसवं ३. ३३, २; ३६, ६.
प्रऽसवस्य ५. ८१, ५.
प्रऽसविता ४. ५३, ६; ७. ६३, २.
प्रऽसवे १. १०२, १; ९; १५९, ५;
३. ३३, ६; ५. ४२, ९; ६. ७१,
२; ७. ८२, ४; ८. १००, १२;
९. ५०, २; १०. १११, ८;
१३९, १.
प्रऽसहः १०. ७४, ६.
प्रऽसह १. १२९, ४[२]; ६. १७, ४.
प्रऽसहा ५. २३, १; ८. ४६, २०.
प्रऽसहानः १०. ९९, २.
प्रःऽसाधनः १०. ५७, २.
प्रऽसाधनं १०. ९१, ८.
प्रऽसितयः ७. ३२, १३.
प्रऽसितस्य ४. २७, ४.
प्रऽसितासः १०. ७७, ५.
प्रऽसितिः २. २५, ३; ६. ६, ५; ७.
३, ४; १०. ९२, ४.
प्रऽसितिं ४. ४, १[२]; २२, ७; १०. ४०,
१०; ८७, ११; १५.
प्रऽसितौ ५. ८७, ६; ७. ४६, ४; १०४,
१३; १०. ३४, १४.
प्रऽसीदतः १०. ३२, १.
प्रऽसुपः ९. ६९, ६.
प्रऽसुवन् ४. ५३, ३; ७. ४५, १.
प्रऽसुवती ७. ७७, १.
प्रऽसूतः ३. ५४, १९; ६. ७५, ५;
१०. १६७, ४.
प्रऽसूता १. ११३, १; ६. ७५, ११.
प्रऽसूताः ३. ३०, ९; ७. ६३, ४.
प्रऽसूवरीः १०. ९७, ३.
प्रऽसूषु १. ६७, ५; ९५, १०.
प्रस्कण्वं ८. ३, ९; ५१, २.
प्रस्कण्वस्य १. ४४, ६; ४५, ३.
प्रस्कण्वाय ८. ५४, ८.
प्रऽस्तरं १०. १४, ४.
प्रऽस्तुतिः १. १५३, २.
प्रऽस्तुभानः ४. ३, १२.
प्रऽस्तोकः ६. ४७, २२.
प्रऽस्थावानः ८. २०, १.
प्रऽस्थितं २. ३६, ४; ३७, २.
प्रऽस्थितस्य १. ९३, ७; १०. ११६,
२; ७.
प्रऽस्थिता ३. ४, ४; १०. ११६, ८.
प्रऽस्थिताः ९. ६९, ८.
प्रऽस्थितान् १. २३, १; ७. ९८, २.
प्रऽस्थिते ८. ३५, २३.
प्रस्नातीःऽइव ८. ७५, ८.
प्रऽस्नापयंति ९. ९८, ६.
प्रस्फुरन्ऽइव ७. ८९, २.
प्रऽस्रवणस्य १. १८०, ८.
प्रऽस्रवणे ८. ६५, २; १०. १४८, २.
प्रऽस्रवणेषु ८. ३३, १.
प्रऽस्वः २. १३, ७; ३. ५, ८; ७. ९,
३; ३५, ७; ८. ६, २०; १०.
१३८, २.
प्रऽस्वनितासः १. ४४, १२.
प्रऽस्वादसः १०. ३३, ६.
प्रऽहंता १०. २७, १.
प्रऽहरन् ६. ४७, १५.
प्रऽहराम १०. ८५, ३७.
प्रऽहां १०. ४२, ९.
प्रहाऽवान् ४. २०, ८.
प्रऽहितः १०. १६५, ४.
प्रऽहुतं २. ३६, १.
प्रऽहुताः १०. ९२, ३.
प्रऽहुतिं ७. ९०, २.
प्रऽहेतारं ८. ९९, ७.
प्रऽहोषिणः ८. ९२, ४.
प्रऽहोषे १. १५०, २.
प्रऽह्वै १०. १०९, ३.
प्राः ६. ४६, ५.
प्राक् ३. ५३, ११; ८. ४, १; १०, ५;
१०. २७, १५; ४४, ७.
प्राक्तात् ७. १०४, १९.
प्राघर्मऽसत् ६. ७३, १.
प्राङ् १. १६४, ३८.
प्राचः २. १५, ३; ९. ९१, ५; १०.
१३१, १.
प्राचा २. २६, ४; ३. ३१, ५; ७.
८३, १.
प्राचाऽजिह्वं १. १४०, ३.
प्राचामन्यो इति प्राचाऽमन्यो ८. ६१, ९.
प्राचि ८. १३, ३०.
प्राची ३. ६, १; ५. २८, १; ८.
१२, १२.
प्राची इति २. २, ७; ३. ६, १०.
प्राचीः ७. ६, ४; १०. ३४, १२;
१५५, ४.
प्राचीनः ७. ७, ३.
प्राचीनं १. १८८, ४; २. २७, ११;
७. ७६, ६; ९. ५, ४; १०. ३७,
३; ११०, ४; ७.
प्राचीनऽरश्मि १०. ३६, ६.
प्राचीनान् २. १७, ५.
प्राचीनेन १. ५४, ५.

प्राचीं ७. ६७, ५; ९९, २; ८. १०१, ८.
प्राचैः १. ८३, २.
प्राचैः १. ११०, २; ३. ७, ७; ५. ४५, ५; १०. १८, ३.
प्राचं १. १८, ८; ३. १, २; १०. ४६, ४; ६६, १२; ८७, ९; १०१, २; १३५, ३.
प्राणः १. ६६, १; ३. ५३, २१.
प्राणतः १. १०१, ५; १०. १२१, ३.
प्राणनं १. ४८, १०.
प्राणं १०. ५९, ६.
प्राणात् १०. ९०, १३; १८९, २.
प्राणिति १०. १२५, ४.
प्रातः १. १६, ३; ५८, ९; ६०, ५; ६१, १६; ६२, १३; ६३, ९; ६४, १५; १२५, ३; ३. ४१, २; ५२, १; ५. १, २; १८, १; ६९, ३; ७६, ३; ७७, १; २; ७. ४१, १[५]; ८. ९४, ६; १०. ४०, ३; ४१, ५; ८८, ६; १४१, ५.
प्रातःऽइत्वः १. १२५, २.
प्रातःऽइत्वा १. १२५, १.
प्रातःऽजितं ७. ४१, २.
प्रातःऽयावानः १. ४४, १३.
प्रातःऽयावानं १०. ४०, १; ४१, २; ६३, १४.
प्रातःऽयावाना २. ३९, २; ५. ७७, १.
प्रातःऽयाम्णः १. ४५, ९.
प्रातःऽयुजं १०. ४१, २.
प्रातःऽयुजा १. २२, १.
प्रातःऽसावः १०. ११२, १.
प्रातःऽसावे ३. २८, १; ५२, ४.
प्रातरित्तिं १. १२५, १; २. १८, १; ४. ३५, ७; ७. ४१, १; ८. २२, १५; ९. ९८, ११.
प्रातर्दनिः ६. २६, ८.
प्रातर्यावऽभिः ५. ५१, ३; ८. ३८, ७.
प्राता ७. १६, ८.
प्रायेऽप्राये २. १८, ८.
प्रायोगाऽइव १०. १०६, २.
प्रावणं ८. ४, ६.
प्रावृतस्य १. १६२, २.
प्रावृताः १०. ८२, ७.
प्रावृषि ७. १०३, ३; ९.
प्रावृषीणं ७. १०३, ७.
प्रावेपाः १०. ३४, १.
प्राशव्यान् ८. ३१, ६.
प्राशुऽषाट् ४. २५, ६.
प्राशूः १. ४०, १.
प्राशूनां ८. ३२, १६.
प्रासि १. ४२, ९.
प्रासि ८. १, २३.
प्रियऽउस्रियस्य १०. ४०, ११.
प्रियः १. २६, ७; ७५, ४; ९१, ३; १२८, ७; १४३, १; १६२, २०; ३. ३२, १२; ४. १७, १९; २५, ५[४]; ५. १, ९; ३७, ५[२]; ५१, ४; ६. १, ६; २, ७; ७. २०, ८; ६८, ५; ७३, २; ८८, ६; ८. १९, ३१; ६४, ११; ८७, १; ९८, ४; ९. ७, ६; २५, ३; ५२, २; ६३, २३; ६४, १०; २७; ७२, ४; ७९, ५; ८५, २; ९६, ९; ९७, ३; १०७, ६; १३; १०. १६, ८; २१, ५; २५, १०; ५६, १; १२३, ५.
प्रियऽक्षत्राः ८. २७, १९.
प्रियऽजात ८. ७१, २.
प्रियऽतमं ५. ७५, १; ९. ३४, ५.
प्रियऽतमस्य ७. ६२, ४.
प्रियऽतमे ७. ९५, ५.
प्रियतमे इति प्रियऽतमे १०. १७, ६.
प्रियऽधामाय १. १४०, १.
प्रियं १. १३, ३; १८, ६; २५, १७; ३१, १७; ७१, ९; ७५, २; ११२, ११; १२८, ८; १४२, ४; १५१, १; १५२, ४; १५४, ५; १६२, २; २. ४, ३; २०, ६; ३. ५, ५; ७, ७; २३, ३; ४. २, ८; ५, ८; ४५, ३; ४९, १; ५२, ७; ५. १९, ४; २३, ३; ४२, २; ८२, २; ८५, १; ६. १६, ४२; ४४, १६; ४८, १; ५१, १; ५३, ६; ६८, ९; ७५, ३; ७. १६, १; ८३, २; ८. २४, ४; ४६, २९; ५०, ३; ८४, १; ९. २, ३; ८, १; १७, ६; ३२, ५; ३८, ६; ५०, ३; ६७, २९; ६८, ९; ७१, ६; ७२, ३; ७५, २; ८६, १०; ४८; १०२, २; १०७, ५; १०८, ८; १०. २२, ३; ५३, ७; ५४, ६; ५५, २; ८४, ५; ८५, २७; ८६, ४; १२; १३; ९६, ११; ११२, ४; ११९, ४; १३२, ३; १३८, २; १५१, २[३].
प्रियऽमेधः १. १३९, ९.
प्रियऽमेधं ८. ५, २५.
प्रियमेधऽवत् १. ४५, ३.
प्रियमेधऽस्तुता ८. ६, ४५.
प्रियऽमेधाः १. ४५, ४; ८. ८, १८; १०. ७३, ११.
प्रियऽमेधाः ८. २, ३७.
प्रियऽमेधासः ८. ६९, ८.
प्रियऽमेधासः ८. ३, १६; ६९, १८.
प्रियऽमेधैः ८. ४, २०.
प्रियऽप्रियं ६. १५, ६.
प्रियऽरथे १. १२२, ७.
प्रियऽव्रतान् १०. १५०, ३[२].
प्रियसासः ९. ९७, ३८.
प्रियऽस्तोत्रः १. ९१, ६.
प्रियस्य १. ८७, ६; २. २७, १७; २८, ११; २९, ७; ५. ६४, ३; १०. १२३, ५.
प्रिया १. ४६, १; ६७, ३; १०४, ८; १५१, ४; १६२, १६; २. ४१, १८; ३. ४३, १; ५५, १०; ४. ५, ४; ५. ४३, ५; ६. ४६, १२; ६१, १०; ६७, २; ३; ९; ७. ३२, १५; ३६, ४; ५६, १०; ८. २७, ६; ७४, ८; ९. ९, १; १०, ९; १२, ८; ९७, ३८; १०२, १; १०. ४९, ४; ७०, ७; ८६, ५; १३२, ६.
प्रियाः १. २६, ७; ८२, २; ८४, ११; ११४, ७; २. ३६, २; ३८, १०; ३. ३२, १५; ९. १०१, ८; १०. ४०, १२; ५५, २.
प्रियाणां ८. १०३, १०.
प्रियाणि १. १२४, ४; ३. ३८, १; ४. ८, ३; ७. २६, ४; ८७, २; ९. ५७, २; ७५, १; ९७, १२; १०. १२३, ७; ८.
प्रियात् १. १४०, ११.
प्रियान् १. १२७, ७.

प्रियां १. ८२, ५; ९. ७३, २; ९६, २३; १०. १३, ४.
प्रियायं ४. ४१, ७; ५. ४८, १.
प्रियासः २. १२, १५; ४. १, १२; १७, ९; ५. ८५, ८; ७. १६, ७; १९, ७; ८; ६०, १; ८. ४८, १४.
प्रियासुं ६. ६१, १०; १०. १३२, ५.
प्रिये १. ४७, १०; ८५, ७; ११०, ७; १८९, ४; ८. १२, ३२; १३, २४; ९. ५५, २; १०. १२६, ४.
प्रिये इति ३. ३२, ७.
प्रियेर्ण ९. ३९, १.
प्रियेभिः ३. ५४, १७; १०. ११२, ४.
प्रियेषु १०. १५, ५.
प्रीणन् ९. ५, १.
प्रीणंति ९. ७४, ४.
प्रीणानः १. ७३, १; २. ११, १७; ४. ३, १४; ७. १३, १.
प्रीणाना ७. ९१, ५.
प्रीणीत १०. १०१, ७.
प्रीणीते ७. ७, ३.
प्रीतः १. ६६, २; ६९, ३; ५. ६, ३.
प्रीता ४. २, १०.
प्रीताः ३. ५७, २.
प्रीताःऽइव १०. ६६, १४.
प्रुष १०. ७७, १.
प्रुषायत् १. १२१, २.
प्रुषायति १०. २६, ३.
प्रुषायन् १. १८०, १; ४. ४३, ५.
प्रुषायंत १. १८६, ९.
प्रुषायंते १. १३९, ३.
प्रुषितऽप्संवः ५. ७५, ६; ८. ५, ३३.
प्रुषितप्सुंऽभिः ८. १३, ११; ८७, ५.
प्रुषितऽप्सुं ४. ३८, २.
प्रुषितस्य १. ५८, २.
प्रुष्णर्वत् ३. १३, ४.
प्रुष्णुते ६. ७१, १; १०. २३, ४.
प्रुष्णुवंति १. १६८, ८.
प्रेणा १०. ७१, १.
प्रेणि १. ११२, १०.
प्रेतारः १. १४८, ५.
प्रेतारा ४. ४१, ५.
प्रेतिंऽइषणि ६. १, ८.
प्रेयः १. १४०, ११.
प्रेषंत् १. १८०, ६.
प्रेषा १. ६८, ३.
प्रेषा ९. ९७, १.
प्रेष्ठः ५. ४३, ७; ७. ३४, १४; ९७, ४; १०. ६१, २३; १५६, ५.
प्रेष्ठं १. १८६, ३; ७. ३६, ५; ८. ८४, १; १०३, १०.
प्रेष्ठा १. १६९, १; ६. ६३, १.
प्रेष्ठाः १. १६७, १०; ६. २६, ८.
प्रेष्ठां ४. ४३, १; ७. ८८, १.
प्रेष्ठौ १. १८१, १.
प्रो इति १. ३९, ५; १६१, १२; १८६, १०; ५. ६, ६; ६. ३७, २; ८. ६२, १; ९. ८६, १६; ८९, १; १०. १३३, १.
प्रोथ ६. ४७, ३०.
प्रोर्थत् ७. ३, २.
प्रोथर्थः १०. ९४, ६.
प्रोर्थतं १०. ११५, ३.
प्रोर्थमानः १०. ११५, २.
प्रोष्ठेऽशयाः ७. ५५, ८.
प्लुते १०. ६३, १७.
प्लवंते १०. १५५, ३.
प्लवं १. १८२, ५.
प्लायोगिः ८. १, ३३.
प्लाशिऽभ्यः १०. १६३, ३.
प्लुषी इति १. १९१, १.
प्सरः १. ४१, ७; ९. २, २; ७४, ३.
प्सरंसे ९. ९६, ३; ९७, २७.
प्सुरः १०. २६, ३.

फ

फर्वरेषु १. १०६, २.
फलं ३. ४५, ४.
फलस्य १०. १४६, ५.
फलिऽगं १. ६२, ४; १२१, १०; ४. ५०, ५; ८. ३२, २५.
फलिनीः १०. ९७, १५.
फल्ग्वेन ४. ५, १४.
फारिवा १०. १०६, ८.
फालः १०. ११७, ७.
फालाः ४. ५७, ८.
फेनं १. १०४, ३; ३. ५३, २२; १०. ६१, ८.
फेनेन ८. १४, १३.

ब

बंहिष्ठं ५. ६२, ९.
बकुरेण १. ११७, २१.
बट् १. ९६, १; १४१, १; ५. ६७, १; ८४, १; ६. ५९, २; ८. ६३, ११; १०१, ११; १२; १०. ९२, ३.
बत १०. १०, १३.
बतः १०. १०, १३.
बद्धः १. २४, १३; १५८, ४; ४. ४०, ४; ५८, ३; १०. ३८, ५; ४८, १०.
बद्धं ६. ७४, ३; १०. ३४, ४; १४९, १.
बद्धंऽइव ८. ६७, १४; १८.
बद्धान् १०. ७३, ११.
बद्बधानः ७. ६९, १.
बद्बधानस्य १. ५२, १०.
बद्बधानाः ४. १९, ८; २२, ७.
बद्बधानान् ५. ३२, १; २.
बद्बधे १. ८१, ५.
बद्बधे १. ८०, १३; ७. ६१, ४.
बधिरा ४. २३, ८.
बधिराः ९. ७३, ६.
बध्यते १०. ८५, २८.
बध्यंतां ४. ५७, ४.
बध्यमाने ४. ४२, ८.
बंधनात् ७. ५९, १२.
बंधनानि १. १६३, ३; ४.
बंधनासः ५. १२, ४.
बंधात् ८. ४०, ८; ६७, १८.
बंधुऽएषे ५. ५२, १६.
बंधुः १. १५४, ५; १६४, ३३; ७. ७२, २; ८. ७३, १२.
बंधुक्षित्ऽभ्यः १. १३२, ३.
बंधुता ३. ६०, १; ४. ४, ११; १०. १४४, ५.
बंधुऽपृच्छा ३. ५४, १६.
बंधुं ५. ७३, ४; ७. ६७, ९; १०. १२९, ४.
बंधुऽमंतं ८. २१, ४.

बंधून् ९. ९७, १७.
बंधेषु १०. ८५, २८.
बप्सत् ८. ४३, ७; १०. १४२, ३; ४.
बप्सतः ७. ५५, २; ८. ७२, १५; १०. ९४, ३; १३.
बप्संता १. २८, ७.
बप्सति ८. ४३, ३; ९. ७९, ४.
बप्संती इति १०. ७९, १.
बबाधे २. १४, ४; ४. २३, ७.
बबाधे १०. ६८, ९.
बबृहाणस्य ५. ४१, १२.
बभंज ८. ४, ५.
बभसत् ४. ५, ४.
बभाज १. १६४, ८.
बभूतु १. १२७, १०.
बभूथ १. १६५, ५; १७५, ६; १७६, ६; १७८, १; २. १८, ७; ४. १०, २; ५. १, ९; ६. २१, ८; ७. १००, ६; ८. २३, ६; ९८, ५; १०. ६, ७.
बभूथ १. ६९, १; १०२, ९; ६. २९, ३; ३६, ४; ५१, ६; ७. २१, ८; ८. ९६, १८; १०. १८, ८.
बभूयाः १०. १८३, २.
बभूयात् ४. ५१, ४.
बभूयात् १. २७, २.
बभूव २. १२, ९; ३. ५९, ७; ४. १६, ५; ७. १०३, ७; १०. ३४, १२; ६१, २३; १२१, ३.
बभूव ६. ५१, ६.
बभूव १. ३२, ८; १५; ९५, ६; ८; ३. १, ९; ३, ९; ६. १८, ४; ४७, १८; ८. ५८, २; ९६, २१; १०. ३२, ८; ८२, ७; १२५, ८; १३०, ४; १६८, ३.
बभूवतुः ६. ६२, ५.
बभूवतुः ५. १६, ४.
बभूवथुः ८. ८६, १.
बभूवथुः १. ९३, ९.
बभूवान् १. १६५, ८; ४. १८, ९; १०. २७, २०.
बभूविथ ८. ३३, १९; ९८, ११.
बभूवुः ४. ३३, १.
बभूवुः ७. ८८, ५; १०. ७१, ७.
बभूवुषी १. १६४, ४१.
बभ्रवः ९. ३३, २; ६३, ४; ६; १०. ३४, ५.
बभ्रवे २. ३३, ८; ९. ११, ४.
बभ्राणः ३. १, ८.
बभ्रिः ३. १, १२; ६. २३, ४.
बभ्रुः २. ३३, ५; ९; ५. ३०, १४; ८. २९, १.
बभ्रुऽधृताः ५. ३०, ११.
बभ्रुं ७. ४४, ३; ८. २२, १०; ९. ९८, ७.
बभ्रू इति ४. ३२, २२–२४.
बभ्रूणां १०. ९७, १.
बभ्रूणां १०. ३४, १४.
बभ्रून् १०. ३४, ११.
बभ्रुषु १. १४०, ६.
बभ्रे ३. १, १०.
बभ्रो इति ९. ३१, ५.
बभ्रो इति २. ३३, १५; ९. १०७, १९; २०.
बर्जहे १. ९२, ४.
बर्बृहि १०. १०, १०.
बर्हणा १. ५२, ११; ५४, ३; ५६, ५; १६६, ६; ३. ३४, ५; ५. ७१, १; ६. २६, ५; ४४, ६; ८. ६३, ७; ९. १०, ४; ६९, ५; १०. २२, ९; ३४, ७; ७७, ३.
बर्हणाऽवत् ३. ३९, ८.
बर्हणाऽवता १. ५४, ५.
बर्हय १. १३३, ५; २. २३, ८; ६. ६१, ३; ७. ३१, १२.
बर्हयः १. ५३, ६.
बर्हिः १. १३, ५; ७; ९; २६, ४; ४५, ९; ४७, ८; ६३, ७; ८३, ६; ८५, ६; १०८, ४; १३५, १; १४२, ५; ७; ९; १४४, ६; १७७, ४; १८८, ४; २. ३, ८; ११, १६; ३६, २; ४१, १३; ३. ४, ४; ८; ११; ९, ९; १३, १; १४, २; २४, ३; ३५, ७; ४१, २; ३; ९; ४३, १; ५३, ३; ४. ९, १; ५. १८, ४; २६, ८; ४४, ३; ४६, ५; ६. ११, ५; ६३, ३; ६७, २; ७. २, ४; ७, ३; ११, २; १७, १; १८, ११; २१, २; २४, ३; ३९, २; ४२, ५; ४३, २; ५७, २; ५९, ६; ७५, ८; ९१, ४; ८. १, ८; १७, १; २७, १; ६; २८, १; ३१, ६; ४५, १; ६०, १; ८७, २; ९३, २५; १०२, १४; ९. ५, ४; ८७, १; ४; १०. ३०, १५; ३५, १०; ३६, ५; ७०, ८; ११; ११०, ४; ८.
बर्हिः २. ३, ४; १०. ७०, ४.
बर्हिःऽइव १. ११६, १; ५. ६२, ५.
बर्हिःऽस्थां ३. ४२, २.
बर्हिषः ६. १२, १; ७. ३३, १; ४३, ३; ८. १३, ४; १५, ५; १०. ३५, ९; १३१, २.
बर्हिषि १. १२, ४; १६, ६; ३१, १७; ४४, १३; ४७, ४; ८५, ७; ८६, ४; १०१, ९; १०९, ५; १७३, १; २. ६, ८; ३६, ३; ३. ३५, ६; ४. ६, ४; ५. ११, २; ७२, १–३; ६. १६, १०; ५२, १३; ६८, ११; ७. १३, १; ४४, २; ४६, ४; ८. १३, २४; १७, ११; २३, २६; ६९, ५; ९. १९, ३; ५५, २; ५९, ३; ७१, ६; ७२, ४; ९५, २; १०. १४, ५; १५, ११; १७, ८; ३०, १४; ४३, २; ४४, ५; ६३, १; ९०, ७.
बर्हिष्टं ३. १३, १.
बर्हिष्मती १. ११७, १.
बर्हिष्मंते १. ५१, ८; ५३, ६; ५. २, १२.
बर्हिष्मत्ऽभिः ८. ७०, १४.
बर्हिष्मान् ९. ४४, ४.
बर्हिष्येषु १०. १५, ५.
बर्हिऽसदः १०. १५, ४.
बर्हिऽसदः ९. ६८, १; १०. १५, ३.
बर्हिऽसदं २. ३, ३; ५. ४४, १.
बर्हिऽसदा ७. २, ६.
बर्हीः ४. १६, १२.
बर्हीत् १. १००, १८; ४. २८, ३.
बलऽदाः ३. ५३, १८; १०. १२१, २.
बलऽदेयाय १०. ८३, ५.
बलं १. ३७, १२; ८०, ८; १७९, ६; ३. ५३, १८[३]; ५. ५७, ६; ६. ४७,

३०; ७. ८२, २; ९. ११३, १; १०. ८७, २५; ११६, ५; १३३, ५.
बलवत्ऽतमां १०. १४५, १.
बलऽविज्ञायः १०. १०३, ५.
बलात् १०. १५३, २.
बलानि १. ९३, १२; १०. २८, ११; ५४, २.
बलाय ३. १८, ३; १०. १८, ९.
बलिनः १०. ८५, २.
बलिं १. ७०, ५; ५. १, १०; ७. १८, १९; ८. १००, ९.
बलिऽहृतः ७. ६, ५; १०. १७३, ६.
बल्वजऽस्तुका: ८. ५५, ३.
बल्बूथे ८. ४६, ३२.
बळा ८. ८०, १.
बष्कये १. १६४, ५.
बस्तः १. १६१, १३.
बस्नि १. १२०, १२.
बहवः २. १८, ३; ४. २५, ५; ७. ६६, १०; ९. ७२, २; ८५, ३; १०. १०१, १; १०७, ३; १४२, ५.
बहवे १०. १०२, ८.
बहु २. १३, १३; १४, १२; २४, ४; ६. १०, ४; १०. १०, ११; ३४, १३; ५२, ४.
बहुऽअन्नां १०. १४६, ६.
बहुः ६. ७५, ५.
बहुऽत्रा १०. १६४, २.
बहुधा १. १६४, ४६; ८. ५८, १; २; १०. ५१, १–४; ११४, ५; १६४, १.
बहुऽपाय्ये ८. २७, २२.
बहुऽपाय्ये ५. ६६, ६.
बहुऽप्रजाः १. १६४, ३२.
बहुऽभिः ६. १, ३.
बहुऽभ्यः १. ८४, ९; ९३, ४; १६१, ९; १०. १४, १.
बहुलऽअंतासः १०. ४२, ८.
बहुलऽअभिमानः १०. ७३, १.
बहुलः २. १, १२.
बहुलं ३. १, १९; ५. ५५, ९; ६. ५१, ५; ९. ७२, ८; १०७, २१; १०. ४२, ५.
बहुला १. १८९, २; ६. १९, ३; १०. १०१, ८.
बहुलाः १. ५४, ९; ३. ३१, १९.
बहुलानि ७. ७६, ३.
बहुलाभिः ३. ५३, २१.
बहुले १०. ४८, १०.
बहुले इति १. १८५, ७; ४. २३, १०; १०. १७८, २.
बहुऽसूवरी २. ३२, ७.
बहूनां २. ३५, १२; १०. ५५, ५; ८४, ४.
बहूनि ४. १८, २.
बहोः १०. १४२, ३.
बव्हीः १. १८८, ५; १०. ९७, १८; १२४, ४.
बव्हीनां १. ९५, ४; ६. ७५, ५.
बाकुरं ९. १, ८.
बाणाः ६. ७५, १७.
बाधः ६. ११, १; ८. ४५, ४०; ९. १०५, ६.
बाधत ५. २९, ६.
बाधतां ६. ४७, १२.
बाधतां ७. ५०, २; १०. ३५, ३; १६२, १.
बाधते १. ३५, ९; ५६, ४; ९२, ५; ६. ६४, ३; ९. ९७, १०; १०. १४५, १.
बाधते १. ५१, १०; ७. ६९, ३; ८. ५, ३४; ९. ७०, ५; १०. ३३, २; १२७, २.
बाधथाः १०. १८, ११.
बाधध्वं ७. ५६, २०.
बाधध्वे १०. ९७, १२.
बाधते १. ८५, ३.
बाधंते ६. ६५, २.
बाधमानः १. ३५, ३; ३. ८, २; ६. ४७, ३०; ९. ९७, ४३.
बाधमाना ३. ५३, १५; ५. ८०, ५; ७. ७७, १; ७८, २.
बाधमानाः १. ९०, ३.
बाधसे ६. ४६, ४; ९. ९४, ५; १०. ३७, ४.
बाधसे २. २३, ५.
बाधस्व १. २४, ९; ३. १५, १; १०. ९८, १२.
बाधस्व ६. ५, ६; ६, ६; १६, ३२; ८. ६४, २; ९. ६६, १९; १०. ४२, ७.
बाधात् ९. ७०, ९.
बाधामहे १०. १२८, ९.
बाधितः ३. ३०, ३; ८. ७३, १८.
बाधिताय ६. १८, १४; ४९, १३; ७. ९१, १.
बाधितासः १०. ८०, ५.
बाधितेभ्यः ४. ३०, ४.
बाधिष्ट ७. २३, ३.
बाधे १. ६१, २; १३२, ५.
बाधे ६. ५०, ४.
बाधेथां ६. ७४, २.
बाबधे ६. २९, ५; ७. ३६, ५.
बार्हतैः १०. ८५, ४.
बाळ्हऽसृत्वा १. १२२, १०.
बाळ्हे १. १८१, ७.
बाहवः १०. १०३, १३.
बाहवा २. ३८, २; ५. ६४, २; ७. ६२, ५.
बाहुऽओजसः १. १३५, ९; ८. २०, ६.
बाहुऽओजसा ८. ९३, २.
बाहुऽओजाः १०. १११, ६.
बाहुऽक्षदः १०. २७, ६.
बाहुऽच्युतः १०. १७, १२.
बाहुऽजूतः ५. ५८, ४.
बाहुता ८. १०१, २.
बाहुताऽइव १. ४१, २.
बाहुऽभिः १. ८५, ६; ३. २९, ६; ६. ६७, १; ७. ९८, ४.
बाहुऽभ्यां २. १७, ६; २४, ७; ४. २२, २; ७. २२, १; ८. १०१, ४; १०. ७, ५; ८१, ३; १६३, २.
बाहुं ६. ७५, १४; १०. १०, १०.
बाहुऽवृक्तः ५. ४४, १२.
बाहुऽशर्धी १०. १०३, ३.
बाहुषु १. १६६, १०; ८. २०, ११; १०१, १३.
बाहू इति १. ९५, ७; १०२, ६; १६३, १; १९०, ३; ३. ५१, १२; ४.

५३, ३; ४; ५. ४३, ४; ६. ४७, ८; ७१, १; ५; ७. ४५, २; ७९, २; ८. ६१, १८; १०. ९०, ११; १२; १०२, ४; १२१, ४; १४२, ५.

वाहून् २. १४, ४; १०. ८७, ४.

बाल्होः १. ५१, ७; ५२, ८; ६३, २; ८०, ८; २. ११, ४; ६; २०, ८; ३६, ५; ३. ४४, ४; ४. २२, ३; ५. १६, २; ५७, ६; ६४, १; ६. २३, १; ४६, १४; ५९, ७; ७. २५, १; ८४, १; ८. ९६, ३; ५; १०. ५२, ५; १५३, ४.

बिभर्य ८. ४५, ३५.

बिभर्ति १. १६४, ४; ७. ३४, ७; ९. १०९, १४.

बिभर्ति ४. ५०, ७.

बिभर्ति १. १०५, ४; ३. ५१, ५; ५५, २२; ५६, २; ५९, ८; ५. २, १; ७. ४, ५; ३३, १४; ८७, ४; ८. २९, ३; ९. ८३, ३; ९५, ४; १०. ४, ३; २७, १६; ३१, ८; १२३, ५; १३६, १; १४४, २; १७७, २.

बिभर्मि १०. ३२, ९.

बिभर्मि १०. ४४, ९; १२५, १; २.

बिभर्षि ६. ५३, ८; १०. १३४, ६.

बिभर्षि १. ५५, ८; २. ३३, १०; ५. २, २; ३, २; ८४, १; ८. १,३४; १०. ८४, ६; १५३, ४.

बिभाय १. ८४, १७; ५. ६०, ३; ८३, २.

बिभित्सन् १०. ६१, १३.

बिभिदुः ४. १६, ६.

बिभिदुः १. ८५, १०; ६. ६५, ५.

बिभीतन १०. ६६, १५.

बिभीयात् १. ४१, ९.

बिभीवान् १०. १०५, ३.

बिभृतः ३. ४६, ५; ५. ४७, ५; ८. ४०, ४.

बिभृतः १. ३९, १०; १८५, १; १०. ६४, १४; ८८, १६.

बिभृतां ६. ७५, ४.

बिभृथ १०. ३०, १२.

बिभृथ ८. २०, २६.

बिभृथः ५. ६४, ६.

बिभृथः ५. ६२, ६.

बिभृमसि १०. १४८, २.

बिभृयात् १०. १०, ९.

बिभेद २. १४, ६; ३. ३४, १०; ८. ९३, २; १०. ८९, ७.

बिभेद ८. ६, ६; १०. ६८, ४.

बिभ्यत् १०. ३४, १०; ५१, ४.

बिभ्यतुः १. ९५, ५.

बिभ्युः १. ९४, ११.

बिभ्युषः ६. २३, २.

बिभ्युषा ९. ७७, २.

बिभ्युषी ४. ३०, १०.

बिभ्युषे १. ३९, ७.

बिभ्रत् १. २५, १३; १०३, ४; ११४, ५; १६४, १०; ३. ५५, ९; ४. १६, १४; २२, १; ५. ३०, ५; ६. २०, ९; २३, १; ७. ३३, १४; ९. १४, १; ४४, १; ९६, १९; १०. ५३, ९; ११३, ३; १२३, ७.

बिभ्रतः १. ४५, ८; १२२, १३; १६६, २; ६. ५५, ६; ७. ७४, ४; १०३, ६; ८. ६५, ४; ९. ६७, २९; १०. ५७, ६; ६०, १; ६७, १०; ९४, ६.

बिभ्रतं ३. ५७, ३; ९. ४८, १; १०८, ११; १०. ३७, ८; ११३, ६.

बिभ्रता १. ४७, ३; ६; ५. ७३, २.

बिभ्रति ६. १६, ४०.

बिभ्रति १. १०२, २; ५. ४७, ४.

बिभ्रती १. १००, १६; ११३, १२; १६४, १७; ३. ३०, १४; ५. ५६, ८; ७. ७७, २.

बिभ्रती इति ३. ५४, ८.

बिभ्रतीः २. १३, २; ९. ९९, ४; १०. ३०, १३.

बिभ्रते ३. १०, ५.

बिभ्रतौ ५. ६४, ७; ७५, ३.

बिभ्रमाणाः १०. ३१, ६.

बिलं १. ११, ५; ३२, ११.

बिल्मैः २. ३५, १२.

बिसखाःऽइव ६. ६१, २.

बीजे ५. ५३, १३; १०. ८५, ३७; १०१, ३.

बीजंऽइव १०. ९४, १३.

बीभत्सुः १. १६४, ८.

बीभत्सवः १०. १२४, ८.

बीभत्सूनां १०. १२४, ९.

बीभयत् १. ८०, १२.

बीभिषथाः ८. ७९, ८.

बीरिटे ७. ३६, २.

बुद्बुदऽयाशवः १०. १५५, ४.

बुधंत १०. ६१, १२.

बुधंत ७. ९, ४; ७८, ५.

बुधानः ४. ३३, ८; ७. ६८, ९.

बुधानाः ४. ५१, ८.

बुधि १. १३७, २.

बुध्नः १. २४, ७; ९६, ६; ३. ५५, ७; १०. १११, ८; १३५, ६.

बुध्नं १. ५२, ६; ९५, ८; ९; ४. १९, ४.

बुध्नात् १. १४१, ३; १०. ८९, ४.

बुध्ने २. २, ३; ३. ३९, ३; ६१, ७; ४. १, ११; १७, १४; ७. ३४, १६; १०. ७७, ४.

बुध्नेषु १०. ९३, ५.

बुध्न्यः १. १८६, ५; २. ३१, ६; ५. ४१, १६; ६. ४९, १४; ५०, १४; ७. ३५, १३; ३८, ५; १०. ६४, ४; ६६, ११; ९२, १२; ९३, ५.

बुध्न्या ७. ६, ७; ५६, १४.

बुध्न्येन ४. ५५, ६.

बुध्यध्वं १०. १०१, १.

बुध्यमानाः ५. ३, ६.

बुंदः ८. ७७, ११.

बुंदं ८. ४५, ४; ७७, ६.

बुबुधानः ७. ४४, ३.

बुबुधानाः ४. १, १८; ५. ३०, २.

बुबोधः ७. ३७, ६.

बुबोधति १०. ३२, १.

बुबोधथ १०. ६४, १३.

बुभुज्महे ८. ६७, १६.

बुभुज्रिरे १. १३८, ३[२].

बुभूषन् १. ३२, ७.

बुसं १०. २७, २४.

बृबत्ऽउंक्थं ८. ३२, १०.

बृबुः ६. ४५, ३१.

बृबुं ६. ४५, ३३.

बृबूंकं १०. २७, २३.

बृसंयस्य १. ९३, ४; ६. ६१, ३.

बृहत् १. ७, १; ९, ७; ८; १०; ४४, २; ४५, ८; ४६, १; ५२, ९; ५६, ४; ७४, ९; ७५, ५; ९१, ३; ९३, १०; १२५, २; १३६, १; २[६]; १५१, ४; १६०, ५; २. १, १६; २, १३; ७, ४; ११, २१; १३, १३; १४, १२; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; २३, १९; २४, १६; २७, ७; १७; २८, ११; २९, ७; ३३, १५; ३५, १५; ३९, ८; ४०, ६; ४२, ३; ४३, ३; ३. २, १४; ३, ११; १०, ५; १८, ४; २७, १५; २९, ८; ३७, १०; ५३, १५; ४. ५, १; ६; ५. १, १०; १०, ४; १६, १; १७, ३; १८, ५; २५, ७; ८; २७, ६; ३६, ४; ३९, ३; ४३, १५; ४४, ६; ५५, १; २; ५७, ८; ६४, ६; ६६, ५; ६७, १; ६८, १; ७३, १०; ७९, ७; ८५, १; ८६, ६; ६. १६, ११; १२; २१; १७, ४; ७; २८, ६; ३०, २; ५०, ३; ७५, १५; ७. २, १; ८, ४; ४५, ४; ५८, ३; ६२, १; ७२, ४; ८४, २; ९४, ४; ९६, १; ८. ९, १७; १५, २; ७; १८, २०; २०, ६; २३, ११; २५, ४; ३१, ७; ५६, ५; ६५, ११; ६६, १; ७२, ६; ७४, ९; ८९, १; ४; ७; ९८, १; १०१, १४; १०२, १; ९. ५, ५; २०, ४; ४४, ६; ५६, १; ६१, १६; ६२, १०; ६६, २४; ८३, ५; ८६, ४०; ९७, ४०; ९८, ८; १०७, १५[२]; १०८, ८; ९; १०. १०, ६; १४, १६; २१, ८; ३५, ६; १०; ६३, ४; ६४, १५; ६५, १; ५; ६६, ४; ७०, ७; ९४, ४; ९६, १०; १७०, १–३; १७६, १; १८१, २.

बृहतः १. २५, ९; ५२, १३; ५४, ४; ५९, ५; ७१, २; १५१, ४; २. २, ७; १६, २; ३. २, ८; ३, ७; १५, १; ४; १६, ६; ३०, १८; ५३, ५; ४. १, १७; १०, २; १२, ३; १७, ६; २१, ४; २७, ४; ३०, १४; ५. ४३, ११; ५९, ७; ७६, ४; ८१, १; ८७, ३; ६. २, ४; १३, २; ६५, २; ७. १८, २०; ६१, ३; ८. १, १८; २५, ७; ३२, ३; ९. ७५, १; ११३, ५; १०. ३, २; ४[२]; ५; ७, ३; २७, २१; २८, ६; ३४, १; ३७, ८; ५८, ९; ९८, १२.

बृहता १. ४८, १; १०; १६; ३. २१, ४; २३, २; ५३, १; ४. ५, १; २८, २; ५. २, ९; ११, १; ६. १, ७; १९, १३; ७. ३३, ४; ७८, १; ८. २३, ५; ९. ९७, ३६; १०. ३, १; ८, १.

बृहतां १०. ३६, ११.

बृहती १. ५७, ५; ११३, १९; १२३, २; ३. ३३, ५; ५. ४३, ८; ८०, २; ६. ४९, ४; ६१, १३; ७. ९९, ६; १०. १३०, ४.

बृहती इति १. ७२, ४; १४४, ६; १८५, ६; ४. ५६, १; ७. ३५, ३; ५३, १; ८७, २; ९. ५, ६; १०. ३६, १; ११०, ६.

बृहती इवेति बृहतीऽइव १. ५९, ४.

बृहतीः ३. १, ५; २२; ५१, १; ५. ४३, १; ६. १, १२; ८. ५२, ९; १०; ९. १३, ४; ४२, ६; ४९, १; ७२, ९; ८७, ९; ९६, २२; ९७, २५; १०. १२१, ७; ९; १३४, ३.

बृहतीः १०. ११०, ५.

बृहतीभिः ४. ४१, ११.

बृहतीभ्यः ८. ३, १९.

बृहतीं ५. ४३, ६; ८०, १; ६. २२, १०; १०. २७, १७; ६७, १; ७४, ४.

बृहत्ऽउंक्थः ३. २६, ४; १०. ५६, ७.

बृहत्ऽउंक्थात् १०. ५४, ६.

बृहत्ऽउक्षः ३. २६, ४.

बृहत्ऽउंक्षा १०. ६९, ७.

बृहते १. ९, १०; ५४, ३; ५७, १; १३६, ६; ३. ३४, ४; ४. ३, ८; ५. १२, १; ४३, ५; १५; ४७, ७; ६. ६८, ९; ८. ८९, ३; ९८, १; १०३, ८; ९. १५, २; ६९, १०; ९६, ४.

बृहत्ऽकेंतुं ५. ८, २.

बृहंत्ऽगिरयः ५. ५७, ८.

बृहत्ऽदिंवः ५. ४३, १३; १०. १२०, ८; ९.

बृहत्ऽदिंवस्य ४. २९, ५.

बृहत्ऽदिवा २. ३१, ४; ५. ४१, १९; ४२, १२; १०. ६४, १०.

बृहत्ऽदिवाः १०. ६६, ८.

बृहत्ऽदिंवेषु २. २, ९; ४. ३७, ३; ९. ७९, १.

बृहत्ऽदिंवैः १. १६७, २.

बृहत्ऽभांनुः १. २७, १२.

बृहत्ऽभिः २. ११, १५; ४. ५६, ४; ६. १, ११; ४८, ७.

बृहत्ऽभ्यः ४. ५४, ५.

बृहत्ऽमते ९. ३९, १.

बृहत्यै ४. ३, ७.

बृहत्ऽरथं १. ३६, १८; १०. ४९, ६.

बृहत्ऽरथा ५. ८०, २.

बृहत्ऽरयिं ६. ४९, ४.

बृहत्ऽरये १. ५७, १.

बृहत्ऽरेणुः ६. १८, २.

बृहत्ऽशंरीरः १. १५५, ६.

बृहत्ऽश्रंवसः १०. ६६, १.

बृहत्ऽश्रंवाः १. ५४, ३.

बृहत्ऽसुम्नः ४. ५३, ६.

बृहद्भानो इति बृहत्ऽभानो १. ३६, १५; ८. ८९, २; १०. १४०, १.

बृहन् २. १, १२; ३. ५२, ४; ६. २४, ३; ८. १५, ९; ४५, २; ७४, ४; ९. ७५, १; १०. १, १; ३; २७, १४.

बृहंतः २. ११, १६; ३. १, १४; ४३, ६; ८. ४४, ४; ८८, ३; ९. ९१, ५.

बृहंतं १. २, ८; ३५, ४; ९२, ८; ११७, २३; १६४, ५२; २. ४, ८; १०, ४; १५, २; ३. ३, २; ३२, ७; ४. ४४, ६; ५. २६, ३; ४३,

१२; ६८, ५; ६. १, ३; ६, ७; १५, १९; १९, २; १०; ४९, १०; ७. १, २४; १०, ४; ७७, ६; ८६, १; ८८, १; ५; ९९, २; ८. ४२, २; ९. ९७, २१; १०. २८, ९; ४७, ३; ८; ८८, ३; १३; ९१, १५.

बृहंता ६. ४७, ८; ७. ४५, २; ९९, ६.

बृहंता ४. ४१, ११.

बृहंताऽइव १०. १०६, ९.

बृहस्पतये ९. ८५, ६.

बृहस्पतिः १. ६२, ३; ८९, ६; ९०, ९; १०५, १७; १३९, १०; १६१, ६; १९०, २; ७; ८; २. २३, १३; ४. ५०, १; ४; ५; ५. ४६, ५; ६. ७३, १; २, ३^{2}; ७. ९७, २; ४; ७; ९. ५, ११; ८१, ४; १०. १४, ३; १७, १३; ३६, ५; ४२, ११; ६४, ४; १५; ६७, ३–५; ८; ६८, ३–९; ११; १२; ९२, १०; ९८, ७; १०३, ८; १०८, ६; ११; १०९, ५; १२८, ७; १४१, २; १६१, ४; १७३, ५; १८२, १.

बृहस्पतिना ८. ९६, १५; १०. ६८, १०.

बृहस्पतिऽप्रसूताः १०. ९७, १५; १ ९.

बृहस्पतिं १. १४, ३; १९०, १; ३. २०, ५; २६, २; ६२, ५; ६; ४. ५०, ७; ५. ४२, ७; ४३, १२; ५१, १२; ७. १०, ४; ९७, ५; ६; ८; ८. १०, २; १०. १३, ४; ३५, ११; ४७, ६; ६५, १०; ६७, ९; १०; ६८, १; १४१, ३–५.

बृहस्पते ९. ८०, १.

बृहस्पते १. १०६, ५; १९०, ५; २. २३, २–४; ६–८; १०; १२; १४–१६; १८; २४, १; ३०, ४; ९; ३. ६२, ४; ४. ५०, २^{2}; ३; ६; ११; ५. ४२, ८; ६. ४७, २०; ७. ९७, १०; १०. ६८, २; ७१, १; ९८, १; ३; १००, ५; १०३, ४.

बृहस्पते ४. ५०, १०.

बृहस्पतेः १. १९०, ४; २. २४, १०; ४. ४०, १; १०. १३०, ४; १६७, ३.

बेकुऽनाटान् ८. ६६, १०.

बोधं १. १४७, २; ७. २१, १; २२, ३; ४; १०. १५६, ५.

बोधंत् ४. १५, ७.

बोधंतं २. ३६, ६; ८. ३५, ४.

बोधतं ८. ९, ३; ३८, १; १०. ९२, १२.

बोधंति २. २५, २; ५. १०, ४.

बोधंतु २. ३२, ४.

बोधंतु १. २९, ४.

बोधय १. १२, ४; २२, १; १२४, १०; १३४, ३; ५. १४, १; ७९, १; ८. ९, १७; १०. ४२, २.

बोधयत ८. ४४, १.

बोधयंतः ७. ४४, २.

बोधयंती १. ९२, ९; ११३, ८; १२४, ४; ५. ४७, १; ८०, २; ७. ७९, १.

बोधयितारं १. १६१, १३.

बोधाति १. ७७, २.

बोधामसि ७. २१, १.

बोधि १. ७६, ४; ३. ५१, ६; १०. ११२, १०.

बोधि १. २४, ११; ३१, ९; ४४, ६; १३१, ६; २. २, ११; ६, ४; ९, २; २३, १९; २४, १६; ३३, १५; ३. ४, १; १४, ७; १५, २; १९, ५; ३०, २१; ३१, १४; ४. ३, ४; १६, १७; १७, १७; १८; २२, १०; ५. ४, ९; २४, ३; ६. २१, ५; १२; ४६, ४; ७. ७५, २; ९६, २; ८. ३, १; ४३, २७; ४४, २२; ४५, १९; ५४, ५; ७४, १२; ८८, ६; ९३, २१; १०. ४४, ९; ८३, ६; १००, १; १३३, १; १६७, २.

बोधित्ऽमनसा ५. ७५, ५.

बोधित्ऽमनाः ८. ९३, १८.

बोभवीति ३. ५३, ८.

ब्रध्नः ९. ९७, ५२; १०. २०, ९.

ब्रध्नं १. ६, १; ७. ४४, ३; ८. ४, १४.

ब्रध्नस्य ३. ७, ५; ३. ४, १३; ६९, ७; ९. ११३, १०.

ब्रव १०. ३९, ५.

ब्रवः ४. ३, ५–७; ७. ६०, १.

ब्रवः ४. ३, ८; १०. १०, ६.

ब्रवंत् १. १५६, २; ६. ५४, १; २; ७. ६४, ३.

ब्रवत् १. ८४, १७; १०. १७३, ३.

ब्रवंन् ९. ३९, १.

ब्रवसि १. १३९, ७.

ब्रवाणि ६. १६, १६.

ब्रवाणि १०. ९५, १३.

ब्रवाम ५. ३०, ३; ४१, १३; ६. ५६, ४.

ब्रवाम २. २८, ८; ४. २०, १०; २३, ६; ५८, २; ५. २९, १३; ४१, ११; ४२, ६; ६. ६७, १०; १०. ११२, १.

ब्रवामहे ५. ५१, १२.

ब्रवावहै १. ३०, ६.

ब्रवीतन १. ८४, ५; ८. ९२, २.

ब्रवीति १०. २७, ३.

ब्रवीति १०. ६१, १२.

ब्रवीतु १. ३५, ६; १६४, ७; ५. ६५, १; ६. ७५, १२.

ब्रवीमि १. ८४, १९; ९. ८२, ४.

ब्रवीमि ३. ५४, १०; १०. १८, १; ७९, ४; ११७, ६.

ब्रवीषि ४. ४२, ७.

ब्रवैते इति ६. २५, ४.

ब्रह्म १. १०, ४; ३७, ४; ४७, २; ६२, १३; ७५, २; ८०, ९; ८८, ४; १०५, १५; ११७, १०; २५; १२९, ४; १५२, ५; ७; १५७, २; १६५, ११; २. १२, १४; १८, ७; २०, ५; ३४, ७; ३७, ६; ३९, ८; ४१, १८; ३. ८, २; २९, १५; ४१, ३; ५३, १२; १३; ४. ६, ११; १६, २०; २१; २२, १; ५. २९, १५; ४२, २; ८५, १; ६. १६, ३६; १७, ३; १३; २३, ५; ३५, १; ३; ३८, ३; ४; ५२, २; ७५, १९; ७. २२, ३; २४, ४; २८, १; २; ३१, ११; ३५, ७; १४; ३६, १; ३७, ४; ६१, ६; ९७, ९; १०३, ८; ८. १, ३; ३, ९; ५, १३; ६, ९; २४, १; ३२, १७; ३३, १३; ३५, १६; ३७, १; ५२, ९; ५३, ८; ६३, २; ६९, ९; ८९, ३; ९०, ३; ९. ६७, २३; ७१, १; ८६, ४१;

१०. ४, ७; १३, १; २२, ७; ३०, ११; ४९, १; ५०, ६; ६१, १; ७; ६५, ११; १४; ६६, १२; ८०, ७; ८९, ३; ११४, ८; १२०, ८; १४१, ६; १४८, ४.

ब्रह्मऽकाराः **६.** २९, ४.

ब्रह्मऽकिल्बिषे **१०.** १०९, १.

ब्रह्मऽकृतः **७.** ३२, २; **१०.** ५०, ७; ५४, ६; ६६, ५.

ब्रह्मऽकृता **३.** ३२, २; **७.** ९, ५.

ब्रह्मऽकृतिं **७.** २८, ५; २९, २.

ब्रह्मऽकृते **८.** ६६, ६.

ब्रह्मऽचारी **१०.** १०९, ५.

ब्रह्मऽचोदनीं **६.** ५३, ८.

ब्रह्मऽजाया **१०.** १०९, ३.

ब्रह्मऽजायां **१०.** १०९, २; ६; ७.

ब्रह्मऽजूतः **३.** ३४, १; **७.** १९, ११.

ब्रह्मणः **१.** १८, ४; ३८, १३; ४०, ३; ५; **२.** २३, १७; १९; २४, २; ४; ५; ८; ९; ११; १३–१६; २५, १–५; २६, २–४; **२.** २४, २; **३.** २९, १५; **५.** ४६, ३; **६.** ५२, ३; ७५, १७; **७.** ४१, १; ४४, १; ९७, ३[२]; **८.** २७, १; **९.** ९७, ३४; **१०.** ५३, ९; ६५, १; ६७, ७; ७२, २; १७३, ३.

ब्रह्मणः **२.** १२, ६; **१०.** २८, ११.

ब्रह्मणः **१.** १८, १; ३; ५; ४०, १; **२.** १, ३; २३, १; ५; ९; ११; **६.** १६, ३०; **७.** ९७, ९; **९.** ८३, १; **१०.** १५५, २; १६४, ४; १७४, १.

ब्रह्मणा **१.** २४, ११; ३१, १८; ८२, ६; ८४, ३; ९३, ६; ११७, ११; १२४, १३; १६२, १७; **२.** २, ७; १०; १६, ७; १७, ३; २४, ३; १५; **३.** १८, ३; ३५, ४; ५१, १२; **४.** ३६, ७; **५.** ४०, ६; ४२, ४; **६.** ३५, ५; ५०, ६; ६५, ५; **७.** ३३, ३; ४; ११; **९.** ११३, ५; **१०.** ५०, ४; १२०, ५; १६२, १; २.

ब्रह्मणां **२.** २३, १; २.

ब्रह्मणां **८.** ३२, १६.

ब्रह्मणि **६.** २३, १.

ब्रह्मणि **१.** १०८, ७.

ब्रह्मणे **१.** ११३, १९; **४.** ४, ६; **७.** १३, ३; ६०, ११; ९७, ८; **९.** ९६, १०; **१०.** ३०, १; ११२, ८; १२२, २.

ब्रह्मणे **१.** १०१, ५; **४.** ५०, ९.

ब्रह्मण्यतः **२.** २०, ४; **६.** २१, ८.

ब्रह्मण्यते **४.** २४, २.

ब्रह्मण्यंतः **२.** १९, १; ८; ३४, ११.

ब्रह्मण्या **८.** ६, ३३.

ब्रह्मऽद्विषः **२.** २३, ४; **५.** ४२, ९; **८.** ४५, २३; ६४, १; **१०.** ३६, ९; १६०, ४; १८२, ३.

ब्रह्मऽद्विषे **६.** ५२, २.

ब्रह्मऽद्विषे **३.** ३०, १७; **६.** २२, ८; ५२, ३; **७.** १०४, २; **१०.** १२५, ६.

ब्रह्मान् **३.** १३, ६; **७.** २९, २.

ब्रह्मन् **७.** ३३, ११.

ब्रह्मपुत्रःऽइव **२.** ४३, २.

ब्रह्मऽप्रियं **१.** ८३, २; १५२, ६.

ब्रह्मऽब्रह्म **९.** ७७, ३.

ब्रह्मऽभिः **८.** ४, २.

ब्रह्मऽभिः **१.** ३३, ९.

ब्रह्मऽभ्यः **८.** ४५, ३९; ७७, ५; **१०.** ८५, २९.

ब्रह्मऽयुजः **१.** १७७, २; **८.** १, २४.

ब्रह्मऽयुजा **३.** ३५, ४; **८.** २, २७; १७, २.

ब्रह्मऽवाहः **१.** १०१, ९; **३.** ४१, ३; **६.** २१, ६.

ब्रह्मवाहःऽतमं **६.** ४५, १९.

ब्रह्मऽवाहसं **६.** ४५, ७.

ब्रह्मऽवाहसे **५.** ३४, १; ३९, ५; **६.** ४५, ४.

ब्रह्मऽसंशिते **६.** ७५, १६.

ब्रह्मऽसवैः **९.** ६७, २४.

ब्रह्मा **१.** ८०, १; १५८, ६; १६४, ३५; **२.** १, २; ३; **४.** ९, ४; ५०, ८; ५८, २; **५.** ४०, ८; **७.** ७, ५; **८.** ७, २०; १६, ७; ३१, १; ३३, १९; ६४, ७; **९.** ९६, ६; ११२, १; ११३, ६; **१०.** ५२, २; ७१, ११; ८५, ३४; ३५; ११७, ७.

ब्रह्माऽइव **८.** ९२, ३०.

ब्रह्माणः **१.** १०, १; **५.** ३१, ४; ३२, १२; **७.** ४२, १; **८.** १७, ३; ९६, ५; **१०.** ८५, ३; १६.

ब्रह्माणः **५.** २९, ३.

ब्रह्माणं **६.** ४५, ७; **१०.** ७७, १; १०७, ६; १२५, ५; १४१, ३.

ब्रह्माणाऽइव **२.** ३९, १.

ब्रह्माणि **१.** ३, ५; ६; ५२, ७; ६१, १; १६; ६३, ९; ८०, १६; १६५, २; ४; १४; १७७, ४; ५; **२.** ५, ३; ३४, ६; **३.** ५१, ६; **४.** ३, १५; **५.** २, ६; ३१, १०; ७३, १०; ७४, ३; **६.** २३, ६; ४०, ४; ४७, १४; ६९, ४; **७.** १, २०; २५; १८, ४; १९, ६; २२, ७; ९; २३, १; ३; २९, २; ४३, १; ६१, २; ७०, ५–७; ७२, ३; ४; ८३, ४; ८४, ३; १०४, ६; **८.** १७, २; ३६, ७; ४०, ५; ६२, ४; ६६, ११; ९०, १; ९८, ८; **१०.** ८९, १६; १०४, ६.

ब्रह्मीः **९.** ३३, ५.

ब्राह्मणः **८.** ५८, १; **१०.** ८८, १९; ९०, १२; ९७, २२.

ब्राह्मणस्य **१०.** १०९, ४.

ब्राह्मणा **१.** १६४, ४५.

ब्राह्मणाः **७.** १०३, १; **१०.** ७१, ८.

ब्राह्मणात् **१.** १५, ५; **२.** ३६, ५.

ब्राह्मणान् **१०.** १६, ६.

ब्राह्मणासः **६.** ७५, १०.

ब्राह्मणासः **७.** १०३, ७; ८; **१०.** ७१, ९.

ब्रुवते **५.** ८७, २.

ब्रुवते **१.** ३७, १३; ७७, ३; १३४, २; **८.** ६, ३; २७.

ब्रुवन् **९.** ६३, ९.

ब्रुवंतः **५.** १२, ५; **८.** ४८, १.

ब्रुवंति **७.** २६, ३.

ब्रुवंति १०. २७, ३.
ब्रुवंतु १. ४, ५; ७४, ३; १०. १५, ५; ६३, १.
ब्रुवाणः ३. ५९, १; ६. ३८, २; ७. ३६, २; ९. ९७, ७; १०. ८, ७.
ब्रुवाणा ५. ४७, १.
ब्रुवाते इतिं ३. ५४, ७.
ब्रुवीत ५. ४९, २.
ब्रुवीमहि ८. २१, ११; ९२, ३२.
ब्रुवे १. १७९, ५; १८५, ७; २. ३०, ११; ३. २, ३; ३७, ५; ४. ५१, ११; ५. ६१, ८; ६५, ३; ७. ३१, ६; ४४, ३; ८. २२, १३; २५, २१; ४४, ३; ६७, १०; ८३, ९; ९८, १२; १०. ३५, ७; ६६, ७; ९७, ४.
ब्रूत १०. ५२, १.
ब्रूयात् १०. १३५, ५.
ब्रूपे १०. ९१, ११.
ब्रूहि १. ३५, ११; ६१, १३; ११४, १०; १०. ८७, ८.

भ

भंससः १०. १६३, ४.
भक्तं १. १२७, ५.
भक्तये ८. २७, ११.
भक्तेर्न ७. ८१, २.
भल्कार्य १०. १०९, ७.
भक्षः ६. २८, ५; १०. ३४, १.
भक्षणं १. ११०, ३.
भक्षत् ९. ६७, १०.
भक्षत ८. ९९, ३.
भक्षं ८. ९२, २३; १००, २; ९. ८३, ४; १०. १६७, ४.
भक्षार्य १. १८७, ७.
भक्षि ७. ४१, २.
भक्षीमहि ७. ९६, ६; ९८, ६; ८. ४८, ७; ९. ८, ९.
भक्षीय १. ८१, ६; ४. २१, १०; ५. ५७, ७.
भक्षैः १०. १४८, ३.
भग ३. ५६, ६; ७. ४१, ३[५].
भग ७. ४१, ५[२].
भगः १. २४, ४; ६२, ७; ९०, ४; १४४, ३; १६३, ८; २. १, ७; ११, २१; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; २७, १; ३१, ४; ३. ३०, १८; ३६, ५; ४९, ३; ५४, २१; ५५, १७; ४. ३०, २४; ५५, १०; ५. १६, २; ३३, ५; ४१, ४; ४२, ५; ४६, २; ६; ४८, ५; ४९, ३; ५१, ११; ८२, ३; ६. १३, २; २८, ५; ४९, १४; ५०, १३; ५१, ११; ७. १५, ११; १२; ३५, २; ३८, १; ४०, २; ४१, ५; ६६, ४; ८. १९, १६; ३१, ११; ५४, ५; ९. ८१, ५; ९७, ५५; १०१, ७; १०८, १४; १०. ३१, ४; ३९, ३; ६४, १०; ६६, १०; ८५, २३; ३६; ९२, ४; ९३, ४; ७; १४१, २; १५९, १.
भगःऽइव ३. २०, ४; १०. ६८, २.
भगत्तिं ९. ६५, १७.
भगऽभक्तस्य १. २४, ५.
भगं १. १४, ३; ४४, ८; ८९, ३; ९१, ७; १३४, ५; १३६, ६; १४१, १०; ११; २. १७, ७; ३८, १०; ३. २०, ५; ३०, १९; ५. ७, ८; ४२, १; ४६, ३; ४९, १; ६. ५०, १; ५१, ३; ७. ३६, ८; ३८, ६[२]; ३९, ४; ४१, १; २[२]; ६; ४४, १; ८. ६१, ५; ७; ९. ७, ८; १०, ५; ९७, ४४; १०. ११, ६; ३५, १०; ११; ३९, १०; ४२, ३; ६३, ९; १२५, २.
भगऽइव १. १४१, ६.
भगऽवती १. १६४, ४०.
भगवत्ऽतरः १०. ६०, १२.
भगऽवंतः १. १६४, ४०; ७. ४१, ४; ५.
भगऽवान् ७. ४१, ५; १०. ६०, १२.
भगस्य १. १२३, ५; १३६, २; ३. ६२, ११; ४. ५५, ५; ५. ८२, १; १०. १५१, १.
भगस्यऽइव ३. ५४, १४; ८. १०२, ६.
भगाय ४. ३, ५; ५. ४१, ११; ९. ४४, ५; ६१, ९; १०९, १; १३.
भगे २. ३४, ८.
भगेऽअविता १०. १०६, ८.
भंगं ९. ६१, १३.
भंगुरऽवतः ७. १०४, ७; १०. ७६, ४; ८७, २३.
भंगुरऽवतां १०. ८७, २२.
भङ्धि १०. ८७, ४.
भज १. २७, ५; ४३, ८; ८१, ६; १०४, ६; १२१, १५; ७. २७, १; ४६, ४; ९. ४, ५; १०. ४५, १०[२]; ८५, २९; ११२, १०.
भजतन ७. ५६, २१.
भजतं १०. १०६, ९.
भजंति ४. ५४, १.
भजति ५. ३४, ५; ७.
भजंते ५. ४४, १२.
भजते १. १२३, ४; ३. ३०, ७; ९. ८६, १२.
भजंत १. ६८, २; ५. ७९, ७; १०. १५, ३.
भजंत ८. ४, २१[२]; १०. १०८, ८.
भजंति १०. ११४, १०.
भजंते १. १२५, ६; १०. १०७, २.
भजस्व ४. ३२, २१; १०. ८४, २.
भजाति २. २६, १.
भजानि १०. २७, १०.
भजाम १०. १०८, ९.
भजामहे १. १८७, ९.
भजामहे १. १५६, ३.
भजासि १०. ४८, १.
भजेमहि १. १५७, २; ७. ३२, ७; ८. ४०, ६.
भजेऽरथस्य १०. ६०, २.
भद्रः १. ६७, १; ९१, ५; ८. १९, १९[२]; १०. ३, ३; ३२, ३.
भद्रऽकृत् ८. १४, ११.
भद्रऽजानयः ५. ६१, ४.
भद्रं १. १, ६; ८९, ८[९]; ९४, १४; १०८, ३; ११३, ९; २०; ११५, २; १९०, ५; २. २३, १९; २४, १६; २६, २; ३५, १५; ४१, ११;

४३, २; ३; ३. ९, ७; ५४, २०; ४. १०, १; ११, १; ३९, ४; ५. १, १०; ३०, १२; ८१, २; ८२, ५; ६. २८, १; ६; ७. ६०, ८; ९६, ३; १०४, ९; ८. १९, २०; ४७, १०; १२[२]; ६२, ४; १०. १४, १२; २५, १; ३०, १२; ३२, ७; ३५, २; ३७, ६; ६२, १; ८५, ६; ८६, २३; १३७, ४; १४२, १; १६४, २[३].

भद्रंऽभद्रं १. १२३, १३; ८. ९३, २८.

भद्रया १०. ३, ३; २९, ८.

भद्रऽवाचः ६. २८, ६.

भद्रऽवादी २. ४२, २; ३.

भद्रव्रातं १०. ४७, ५.

भद्रंऽशोचे ८. ७१, ३.

भद्रऽशोचे ५. ४, ७; ७. १४, २; १०. ४५, ९.

भद्रस्य १. १३२, २; २. २९, १; ४. १०, २.

भद्रऽहस्ता १. १०९, ४.

भद्रा १. ८३, ३; ८९, २; ९४, १; ११४, ९; १२३, ११; १२; १३४, ४; १६६, ९; १०; १६८, ७; ३. ३०, ७; ३९, २; ४. ६, ६; २१, ९; ५८, १०; ५. २९, १५; ४९, ३; ८०, ६; ६. १, १२; ४५, ३२; ५८, १; ६४, २; ७४, २; ७. ९६, ३; ८. १९, १९; ८०, ७; १०२, १५; ९. ९७, २; १०. ११, ३; १८, ३; २७, १२; ३२, ९; ६४, ११; ७१, २; ८०, २; १००, ११; १३४, १.

भद्राः १. ४८, १३; ८९, १; ११५, ३; १३२, २; १६३, ५; ४. ५१, ७; ५२, ५; ७. ४१, ७; ८. १९, १९; ६२, १; १०. ३५, ५; ६९, १; ७२, ५.

भद्राणि ७. २६, ४.

भद्रान् ९. ९६, १.

भद्रां १०. ५३, ३.

भद्राय १. ११५, २; १०. ४८, ११.

भद्रायां ६. १, ४; १०.

भद्रे ३. १, २१; ५. ६२, ७.

भद्रे इति १. ९५, ६.

भद्रेण १. ९४, १५; ८. १८, १७.

भद्रेभिः १. ४९, १.

भनक्ति ६. ६८, ६.

भनंति ६. ११, ३.

भनंत ४. १८, ७; ७. १८, ७.

भनंति ४. १८, ६.

भंदत्ऽइष्टये ५. ८७, १.

भंदते ३. ३, ४.

भंदना ८. २४, १५; १७.

भंदनाः ९. ८६, ४१.

भंदनाऽयतः ९. ८५, २.

भंदमानः ३. २, १२.

भंदमाने इति १. १४२, ७; ३. ४, ६.

भंदिष्ठः १. ९७, ३.

भंदिष्ठस्य ५. १, १०.

भयतां १०. ४२, ६.

भयते १. ५८, ५; १६६, ५; ४. १७, १०; ६. ३१, २; ७. ५८, २; १०. ९२, ८.

भयंते १. ८५, ८; १६६, ४; ४. ६, ५; ७. ८३, २.

भयंते २. १२, १३; ४. ३८, ८.

भयं १. १८९, ४; २. २८, १०; ४१, १०; ८. ६१, १६; ९. ६७, २१; १०. ३९, ११.

भयमानः १. १००, १७; २. २९, ६; ३. ३०, १०.

भयऽस्थे २. ३०, ६.

भयस्य १०. ३५, १४.

भया ६. ६, ६.

भयाते १०. २७, ५; २२.

भयामहे ८. ६१, १३.

भये १. ४०, ८; २. २७, ५.

भयेते इति ४. ४२, ६.

भर ८. २, २३; ३२, २४; ९. ६९, १०.

भर १. ४, ७; ८, १; १२, ११; २८, ९; ४९, ५; ५३, ३; ५७, ३; ६१, १२; ६३, ९; ६४, १; ७९, ८; ८१, ७; ९; ९२, १३; १२७, ११; १४०, १; २. ७, १; १७, ७; २१, १; ३०, १०; ३. २९, १; ३; ३०, १९; ३६, ९; ४५, ४; ५३, १४; ५४, १५; ४. २, १३; २०, १०; ३२, २०; ५. ४, ५; ६, १; ८; ९, ७; १०, १; ७; १६, ५; २३, १; २; ३५, १; २; ३८, ४; ३९, १; २; ६. १६, २९; ३६; १९, ६–८; २२, ३; ४२, १; ४; ४४, १३; ४६, ५; ७; ७. १५, ११; २०, ७; २५, २; ३२, ७; २४; २६; ७७, ४; ८१, ५; ८. १, ४; १३, ५; १९, १५; २१, १६; २४, ४; २५; ३२, ८; ३३, १२; ३४, १५; ४५, १५; ४०; ४६, १९; ६०, १८; ६१, ६; ६६, ७; ७७, ८; ७८, १–३; ८१, ७; ८९, ४; ९३, १९; २८; २९; ९८, १०; ९. ४, १०; १९, १; २०, ४; २३, ३; २९, ६; ४०, ४; ६; ५७, ४; ५९, १; ६०, ४; ६१, ६; २६; ६३, १८; ६४, २६; ६५, १८; ८७, ६; १००, २; १०१, ९; १०३, १; १०६, ४; १०. २१, ४; ४२, १; ३; ८३, ३; ११३, १०; १४८, १; १५६, ३; १८०, १; १९१, १.

भरः ६. २६, ४; १०. १७१, २.

भरणे १०. ३१, ६.

भरंत् १. १२१, १३; १७३, ३; २. १९, ५; ४. २६, ४; ५; ५. ३१, ११; ४४, १३; ९. ५२, १.

भरत् १. ६०, १; २. २०, ६; ४. २६, ६; ९. ४८, ३; ४; ९७, २४; १०६, ३; १०. १३, २.

भरंत २. १४, १; ६; ७; ६. १६, ४१; ८. ६२, १.

भरत १. १३६, १; २. १४, २; ८; ३७, १; ३. १०, ५; ५२, ८; ५. ४३, ३; ७. ४६, १; ८. १००, ३; १०. ४०, ६; ७६, ४; १००, २.

भरतः ६. १६, ४.

भरतं १. ९६, ३.

भरतं १. १०९, ७.

भरतस्य ३. ५३, २४; ७. ८, ४.

भरतस्य २. ३६, २.

भरंता १०. १७६, २.

भरताः ३. ३३, ११; १२; ७. ३३,६.
भरतां १०. ५९, ८.
भरताय ५. ५४, १४.
भरति २. १६, २; ३. ५५, ४; ४. १६, १६; २२, ४; १०. ८७, १६.
भरति १. १५२, ३; ४. १७, ९; १०. १३८, ६.
भरते १. १७३, २; २. २४, ९; ८. १९, २३; ९. ९४, ३.
भरते १. ६४, १३; १०४, ३; २. २४, १३; २६, ३; ५. ३२, ९; ७. २४, २; १०. ४६, ८; ७५, ७; १४७, ४.
भरतेभ्यः ५. ११, १.
भरत्ऽवाजः १०. १८१, २.
भरत्ऽवाजं १. ११२, १३; १०. १५०, ५.
भरत्ऽवाजाः ६. २५, ९; ५०, १५.
भरत्ऽवाजान् ६. ४७, २५.
भरत्ऽवाजाय १. ११६, १८; ६. १५, ३; १६, ५; ३३; ३१, ४; ४८, १३; ६३, १०.
भरत्ऽवाजे ६. १७, १४; ४८, ७.
भरत्ऽवाजेषु १. ५९, ७; ६. १०, ६; २३, १०; ३५, ४.
भरथ १०. ९४, १.
भरथः १. १५१, ३, ३. ६२, १.
भरथः १. ११२, २१.
भरद्वाजऽवत् ६. ६५, ६.
भरध्यै ६. ६६, ३; ६७, ४.
भरध्वं १. ६२, २; १२२, १; ३. ६१, ५; ५. ४१, ३; ५; ६. ६६, ९; ७. ४, १; ५, १; १३, १; ३१, १०; ८. २०, ९; १०. १११, १.
भरध्वे ५. ५९, ४.
भरंत १. ७०, ५; ८. ६, २.
भरंत १. ७०, ५; २. १३, २; ५. ७३, ८.
भरंतः १. १, ७; ३. २६, ७; ८. २१, १; १०. ३५, १.
भरंति १. १५१, ८; १५३, १; २. १६, ४; ७. ९२, २; ८. १००, ९.
भरंति १. ११५, ५; ५. १, १०; ६. ४४, २०; ९. ७४, ६; १०. ७९, २; १०२, १०.
भरंती २. ५, ६; ३. ६, १; ३१, ११; ८. ९१, १; १०. ९५, १०.
भरंतीः १०. ३०, १३; ३५, ५.
भरंते ६. ६७, ७; १०.
भरंते १. १०४, ४; १७३, ४; ३. ५५, ७; ५. ११, ४; ७. ७२, ४.
भरं १. ११७, १८; ५. २९, ८; ८. ६६, १; १०. ४४, ५.
भरमाणः ९. ९७, १५; ११०, ५.
भरमाणस्य १. १४८, २.
भरमाणाः १. १३५, ३; ६; ७. २, ४.
भरसे ५. १५, ४.
भरस्व १. ७९, १०.
भरस्व ७. ८८, १.
भरऽहूतये १. १२९, २; ५. ४८, ४.
भरऽहूतौ ८. ६३, १२.
भराणां ८. ४०, ३.
भरात् ४. २, ७.
भराति १. १८०, २; ५. ३, ७.
भराम १. ९४, ४.
भरामसि ६. १६, ४७; ८. ६६, ५; ११.
भरामहे १. ५३, १; ११४, १; २. २०, १; ४. ५६, ५; ८. ८३, ८; १०. ३६, ८.
भरामि १. ६१, २; ३.
भरामि ८. १०२, १९.
भराय १. १११, ५; ३. ५१, ८; ४. २१, ७; ६. १७, ८; २३, ९; ८. १३, ३; ९. ६, ६; १६, ५; ९७, ६; १०६, २; १०. १००, २.
भरासः ९. १०, २.
भरित्रैः ३. ३६, ७.
भरिभ्रत् २. ४, ४; १०. ४५, ७.
भरिभ्रति १०. १२४, ७.
भरिषः ४. ४०, २.
भरीमऽभिः १. २२, १३; १०. ६४, १४.
भरे १. ११२, १; १३२, १²; २; ३. ३०, २२; ५. ३६, ५; ६. ४५, १३; ७. १३, १; ८. १६, ३; ९. ९७, ५८; १०. ४९, १; ४; ५०, ४; १०२, २.
भरे १. ५७, १; १०२, १; १२६, १; १४३, १; २. १६, १; ५. १२, १; १५, १; ४२, १३; ५९, १; ६०, १.
भरेते इति १०. ७९, १.
भरेऽभरे १. १००, २; १०२, ४; ५. ४३, २; ७. ३२, २४; ८२, ९; १०. ६७, ९.
भरेमहि ९. ७९, २.
भरेरत १०. ३६, ९.
भरेषु १. १००, १; १०९, ८; २. २३, १३; ३. ३७, ५; ४. ३८, ५; ८. ५३, ७; ९. ४७, ५; १०. ६३, ९; १०७, ११.
भरेषुऽजां १. ९१, २१.
भर्गः १. १४१, १; ३. ६२, १०; १०. ६१, १४.
भर्तवे ९. ९७, ५०.
भर्ता १०. ७४, ५.
भर्ता १०. २२, ३.
भर्ताऽइव ५. ५८, ७.
भर्ति १. १७३, ६.
भर्ति ६. १३, ३.
भर्मणे १०. ८८, १.
भर्वति १. १४३, ५.
भर्वन् ६. ६, २.
भर्षत् ६. ३८, १.
भल १०. ८६, २३.
भलानसः ७. १८, ७.
भव १. ३६, २; ५८, ९²; ७३, ४; ७६, ३; ९१, १६; १७; १५६, १; १७१, ६; १८९, २; ३. १०, ८; १८, १; ४५, ५; ४. ४, ३; १०, ३; ५. ५, ४; ६. ३३, ५; ४६, ३; ४७, ७²; ७. ७, १; ११, ३; १७, १; ३०, १; ३२, ७; २५; ८. १३, ३; ४५, ८; ७९, ७; ९७, ७; ९. ३१, २²; ८१, ३; ९७, २५; १०. ७, ७²; ६९, ५.
भव १. १, ९; १२, ८; १५, १०; २२, १५; ३१, ३; ४०, १; ५१, ८; ७६, २; ७९, ११; ८१, ८; ९१, ९; १०; १२; १३८, ३²; १८७, २; ८; ९; १०²; ३. १७,

३; २१, ३; ३१, १८; ३७, ६; **४.** १, ५; ३, १५; ४, ५; ३२, १४; ५७, ६; **५.** २४, १; **६.** १५, ९; २५, ७; ४५, २६; ४६, १०; ११; ५५, १; **७.** १५, १४; ४१, ५; ४६, २; ५४, १[२]; ९६, ५; **८.** ४, १८; ४८, ४; **९.** १, ३; ६१, २१; ८८, ७; ९६, ११; १०४, ५; १०५, ५; **१०.** १८, ११; २५, ७; ३३, ३; ३७, १०; ५३, ६; ६९, ४; ७०, १; ८३, ७; ८४, ५; ८५, ४६[३]; १२७, ६; १४१, १; १४८, ४.

भव॑त **१.** २३, १९; १०७, १; **३.** ३३, ९.

भवत **२.** २९, ६; **१०.** १८, २; ११०, ५.

भव॑तः **१.** ९६, ७; **१०.** १४७, १.

भवतः **१.** १६२, १९; **२.** २७, १५; **१०.** १२, १.

भव॑तं **१.** ३४, ११; ९३, १; १५७, ४.

भवतं **१.** ३४, १[२]; १२; ११२, २४; **६.** ६०, ३; **७.** ८२, ९; **१०.** १३, २.

भवतात् **३.** २३, २.

भवतां **३.** ५३, १७; **४.** ५६, १; **७.** ३५, १.

भव॑ति **१.** २८, १; ९५, १; १२७, ३; **२.** २७, १३; **५.** ३४, ३; **७.** ५०, ३; ८३, २; १०१, ३; **१०.** ७१, १०; ११४, १०.

भवति **१.** १७, ५; ५५, ४; १५८, ६; **३.** ५, ४; ८, ४; २९, ११; **४.** २५, २; ३८, ८; **५.** ५४, ९; ६१, ६; ८०, ४; **६.** ७५, १; **७.** ४४, ४; **९.** ७०, ७; **१०.** २७, १२; ४०, ९; ४६, ३; ५२, २; ८५, १९; २८; ३०; ८८, ६; १०९, ५; ११७, ३; ६; १६०, ४.

भवतु **१.** ९०, ९; ९४, ८; १००, १–१५; **४.** १, २०; ५७, ३; **५.** ८३, ८; **६.** ४७, १२; ७५, १२; **७.** ३५, ३; ७; ९; १०; १३; **८.** ७४, ८; ९२, २४; **९.** ७९, ५; ८५, १; **१०.** ६०, ११; ६३, १६.

भव॑थ **३.** ५४, १७.

भवथ **३.** ६०, ४; **५.** ५५, ८.

भव॑थः **१.** ११२, २०; **४.** ४३, ६; **८.** ९, १२; **९.** १११, ३.

भवथः **४.** ४३, ३; **१०.** ३९, ३; ४०, ३.

भव॑न् **२.** १५, ७; **३.** ५, १०; **४.** १६, ७; **८.** १४, १५; **९.** १५, ५.

भव॑तः **७.** ५२, १.

भव॑तं **१.** ६७, ४.

भव॑ति **१.** ८९, ९; **७.** ३२, १७; **९.** ९४, ४; **१०.** १८, ५; १२०, ३.

भवंति **१.** १६४, ३६; **३.** ५७, ४; ५८, २; **४.** ३, ४; **५.** २, ४; **७.** ११, २; १०३, ८; **९.** १०२, ५; **१०.** १४२, ३.

भव॑ती **१.** १६४, २९.

भव॑ती इति **३.** ५४, ७.

भव॑तीः **३.** ७, ३; ५५, १६.

भव॑तु **६.** ५१, ११; **८.** २७, १४.

भवंतु **१.** १०, १२[२]; ९०, ८; **५.** २, ६; ५१, १२; ८३, ७; **६.** १६, ४७; ५२, ९; **७.** १७, ५; ३४, ५; ७; ८[२]; ९–१२; ३८, ७; ५०, ४[२]; **१०.** ९, ४; १८, १२; २९, ६; ३५, १३; ६७, ११; १०३, ११; १२८, ९.

भव॑सि **१०.** ९५, १८.

भवसि **१.** ३१, ५; **२.** १, ४; ९; **३.** १८, ५; **४.** ४, १०; ७, ९; **५.** ३, १; २; ८१, ४; ५; **९.** ८५, ३; **१०.** ९१, ११.

भवा॑ति **१.** ११३, १०; **२.** ३८, ११; **४.** १६, १७; **७.** ७०, ६; **१०.** १०, २; ११; ११, ८.

भवाति **२.** ४१, ११; **५.** ३७, ५[२]; **६.** ४१, ५; **८.** १३, २२; **१०.** १६, २; १०८, ३.

भवा॑म **५.** ४५, ५.

भवा॑सि **२.** ४२, १; **५.** ३, ५.

भवासि **४.** ३१, ३; **८.** ४८, २.

भवित्रं **७.** ३५, ९.

भविष्यति **१०.** ८६, ७.

भविष्यथ **१.** १६१, २.

भवी॑त्वा **२.** २४, ५.

भवी॑यसा **१.** ८३, १.

भवैः॑ **८.** ४५, १८.

भवै॑म **७.** ५२, १; ९७, २.

भवेम **४.** २, १५; **७.** ८, ३; **१०.** ३१, १; ५९, ३.

भव्यं॑ **१०.** ५५, २; ५८, १२; ९०, २.

भव्या॑य **१.** १२९, ६.

भस॑त् **६.** ३, ४; १४, १.

भसत् **१०.** ८६, ७.

भसथः **६.** ५९, ४.

भर्स॑ना **५.** १९, ५; **१०.** ११५, २.

भाः **१.** ४५, ८; ४६, १०; **४.** ५, १; ७, ९; **७.** ८, २; ४; **८.** १, २८; २३, ११.

भाःऽऋ॑जीकः **३.** १, १२; **१०.** १२, २.

भाःऽऋ॑जीकं **१.** ४४, ३; **३.** १, १४.

भाक् **७.** १८, १३; **८.** ८०, ८; ८१, ६; **९.** ७२, ८.

भागः **१.** १३५, २; ३; १६२, ३; ४; १८३, ४; **६.** २२, ४; **८.** ५७, ४; १००, २; **१०.** १६, ४; ७१, ६; ८५, २१; १३०, ५.

भागऽधेयं **३.** २८, ४; **८.** ९६, ८; **१०.** ५२, १; ११४, ३.

भागऽधेयानि **८.** ५९, १.

भागं **१.** २०, ८; २४, ३; ७३, ५; ९१, २३; ११६, १९; १२३, ३; १६१, ६; १६४, २१; ३७; **२.** १०, ६; १७, ७; २३, २; ३८, ५; ७; **३.** १, १९; ४९, ४; ६०, १; **४.** ५४, २; **५.** ८२, ३; **७.** ५६, १४; **८.** ३६, १; ४७, १६; ९७, २; ९९, ३; १००, १; **१०.** ११, ८; १७, ९; ३५, ७; ३९, २; ५१, ७; ८; ६६, २; ८५, १९; ८७, १८; ९८, ११; १००, २; १२४, ३; १७९, १; १९१, २.

भागंऽइव **८.** ९०, ६.

भागस्य **२.** ३६, ४.

भागाः **१०.** ५१, ९.

भागे **१.** १५६, ५.

भाजयत **१०.** ९, २.

भाजयुः २. १, ४.
भार्ति २. ४, ६; ५. ४४, १२; १०. ३, ६.
भाति १. ९२, ९; ११; ९६, ५; १५४, ६; २. ३५, ७; ३. २५, ३; ४४, ४; ५. २, ९; ११, १; २८, १; ७६, १; ८०, ३; ६. ५, ५; ६, ४; ७. ५, २; ९, ३; १०, १; ८. ५८, २; १०. ३, १; २; ४५, ४; ५.
भाऽत्वक्षसः १. १४३, ३.
भानवः १. ३६, ३; ९२, २; ९७, ५; १४३, ३; ३. १, १४; ५. १, १; ६. ६४, २; ७. ७५, ३.
भानवे ५. १६, १; ७. ४, १.
भानुः ३. २२, २; ४. १, १७; ४५, १; ५. ५२, ६; ७. ३४, ७; ९. ८५, १२; १०. १००, १२.
भानुना १. ४८, ९; १५; २. २, ८; ८, ४; १६, ४; ३. २, ३; २१, ४; ५. ३७, १; ६. ६, ६; १५, ५; १६, २१; ४८, ६; ६५, १; ७. ९, ४; ८. ९, १८; ९. ६५, ४; १०. १, १; ३७, ४; १०; ४३, ९; ४५, ४; ७५, ३; ८८, ३; १४०, २.
भानुऽभिः १. ८७, ६; ७. ७७, ५; ८. ७, ८; १०. ३, ५; ६, १; २.
भानुं १. ९२, १; २; ५; ३. ६१, ७; ४. ६, २; १३, २; ५. ५९, १; ६. ६२, २; ७. ३, ६; ६, २; ७९, १; ८. ५, १; १०. ३, २; ५३, ६.
भानुऽमः ५. १, ११.
भानुमत्ऽभिः ६. ४, ६.
भानुऽमंतं ५. १, ११.
भांति ६. ६५, २.
भामः १०. ८३, ४.
भामं ३. २६, ६; ५. ३२, ४.
भामाः ५. २, १०.
भामासः ६. ६, ३; १०. ३, ४; ५.
भामितः १. ११४, ८.
भामिनः १. ८४, १६.
भामिने १. ७७, १.
भामेन १. १६५, ८.
भारत २. ७, १; ५; ६. १६, ४५.
भारतः ४. २५, ४; ६. १६, १९.
भारतं ३. ५३, १२.
भारता ३. २३, २.
भारति १. १८८, ८.
भारती १. १४२, ९; २. १, ११; ३, ८; ३. ४, ८; ६२, ३; ९. ५, ८; १०. ११०, ८.
भारतीभिः ३. ४, ८.
भारतीं १. २२, १०.
भारत्ऽवाजः ६. ५१, १२.
भारऽभृत् ८. ७५, १२.
भारं १. ३१, ३; १५२, ३; ४. ५, ६; ७. ३४, ७.
भारान् ३. ५६, २.
भारि ९. ९७, २३.
भारिति भाः १. १२८, २.
भार्मन् ८. २, ८.
भार्वरस्य ४. २१, ७.
भावयुः १०. ८६, १५.
भाव्यस्य १. १२६, १.
भासः ४. ३३, ४; ६. १२, ५.
भासंदात् १०. १६३, ४.
भासा २. ४, ५; ६. १, ११; ४, ६; १०, ४; ७. ५, ४; १०, १; ८. २३, ५; १०. ३, १; ७७, ५.
भासांसि ६. ४, ३.
भासाऽकेतुं १०. २०, ३.
भासि १. ५०, ४; २. १, १०; २, २; ३. ६, ७; ६. ६४, २; ९. ९७, ३२.
भास्वती १. ९२, ७; ११३, ४.
भास्वतं १०. ३७, ८.
भाहि १. ४८, ९; ९५, ११; ९६, ९; ११३, १९; ३. १५, ३; ६१, २; ६. १, ११; १६, ४५; ७. ७७, ५; १०. २, ७.
भिक्षते ७. ३२, १७.
भिक्षंत ३. ५६, ७.
भिक्षमाणः ३. ६१, ६; ९. ७०, २.
भिक्षमाणाः १. ७३, ६; ७; ४. ४१, ९; ७. ६, ६; १०, ३; ९०, ७; १०. ३१, ५.
भिक्षमाणे इति ३. ३३, २.
भिक्षे १. १७१, १; २. २८, १.
भिक्षेत १. १५२, ६; ८. ७, १५; १८, १.
भित्वा १०. ६८, ७.
भिदः १. १७४, ८.
भिदंतः ४. ३, ११.
भिनत् १. ५२, ५; ५४, ४; ६२, ३; १३०, ७; १७४, ८; २. ११, २०; १५, ८; ४. १७, ३; ८. १, ८; ३२, २५; ६९, १४; १०. ६८, ११.
भिनत्सि ८. ६०, १६.
भिनदः १०. ८९, १४.
भिनदत् १०. ४५, १०.
भिनद्मि १. १९१, १५.
भिंदन् ४. ५८, ७; ७. १०४, २१.
भिंदंतः ४. २, १६; ९. ५३, १.
भिंदति ५. ५२, ९.
भिंदानाः ६. २७, ६.
भिंदुः १. ११, ४.
भिंधि ८. ४४, ११; ४५, ४०.
भिंधि १०. ८७, ५.
भिन्नं १. ३२, ८.
भियं १०. ८४, ७.
भियसे २. २८, ६; ९. १९, ६; १०. १२०, २.
भियसा १. ५२, ९; १०; ५४, १; ८०, ११; ४. १७, २; ५. ३२, ९; ४०, ७; ५९, २; ६. १७, ९; २७, ५; १०. १०८, २.
भियसे ५. २९, ४.
भिया १. ३७, ८; ६१, १४; ६३, १; ८०, १४; १७१, ४; ५. ३६, ३; ५७, ३; ६०, २; ६. १४, ४; ३१, २; ७. ५, ३; ६०, १०; ८. ७, २६; १०. ५१, ६.
भियानाः ४. २२, ६; ६. ९, ७.
भियाने इति २. ११, ९.
भियै ८. ७५, १३.
भिषक् ९. ११२, १; ३; १०. ९७, ६.
भिषक्ऽतमं २. ३३, ४.
भिषक्ति ८. ७९, २.
भिषजः १. २४, ९; ६. ५०, ७.
भिषजा १. १५७, ६; ८. १८, ८; ८६, १; १०. ३९, ३; ५.

भिषजा २. ३३, ४.

भिषजा १. ११६, १६.

भिषज्यतं ८. २२, १०.

भिषज्यथः ८. ९, ६.

भीः १. ३२, १४.

भीःऽइंव १०. १४६, १.

भीतः १. ३२, १४.

भीताय ५. ७८, ६.

भीते इति १०. ५४, १; ५५, १.

भीम १. ९५, ७.

भीमः १. ५५, १; ७०, ६; ८१, ४; १००, १२; १४०, ६; १५४, २; १९०, ३; ४. १६, १४; २०, ६; ३८, ८; ६. ६, ५; ७. १९, १; २१, ४; ९. ७०, ७; ९७, २८; १०. १०३, १.

भीमं २. २३, ३; ३३, ११; ६. ३१, ५; ८. ८१, ३.

भीमऽयुः ५. ५६, ३.

भीमऽसंदृशः ५. ५६, २.

भीमस्य १०. ९२, ८.

भीमा ६. ३, ३; १८, १०; १०. १०९, ४.

भीमाः २. ३४, १.

भीमानि ९. ६१, ३०.

भीमाय १. ५७, ३.

भीमासः ७. ५८, २.

भीमासः १. ३६, २०.

भीरवे २. २८, १०.

भीऽरुभिः १. १०१, ६.

भीषा १. १३३, ६[२]; ७. २१, ३; ८. ९७, १४.

भुजः ५. ७४, १०; ८. ९७, १; १०. २२, १३.

भुजंता ६. ६२, ६.

भुजे १. १०४, ६; ३. २, ९; १०. ९२, ७.

भुजां १०. २०, २.

भुजिं ८. १०२, ६.

भुजी इति ८. ८, २.

भुजे १. ३०, २०; ५१, १; १२७, ८[२]; ११; १५५, ३; ५. ४८, ४; ७३, २; ८. २०, ८; १३; ९. १०१, १४; १०. ४८, ९; १००, १.

भुजेम ४. ३, १३; ५. ७०, ४; ६. ५१, ७; ७. ५२, २; ८८, ६.

भुज्मं १. ६५, ३.

भुज्मा ८. ५०, २.

भुज्युः १०. ९५, ८.

भुज्युं १. ११२, ६; २०; ११६, ३–५; ११७, १४; ११९, ४; ४. २७, ४; ६. ६२, ६; ७. ६८, ७; ६९, ७; ८. २२, २; ४६, २०; १०. ४०, ७; ६५, १२; १४३, ५.

भुज्यै १०. १०६, ४.

भुंजतीनां १०. ८९, १७.

भुंजते ५. ४२, ९.

भुंजते २. २४, १०.

भुनजामहै ७. ८१, ५.

भुनजामहै १०. १९, ६.

भुरजंत ४. ४३, ५.

भुरणा १. ११७, ११; ७. ६७, ८.

भुरणौ १०. २९, १.

भुरण्यति ५. ७३, ६.

भुरण्यति १. १५५, ५.

भुरण्यथः ८. ९, ६; ५९, १.

भुरण्यन् ४. २७, ३.

भुरण्यंतं १. ५०, ६.

भुरण्यवः १०. ४६, ७.

भुरण्यसि १०. ३५, ९.

भुरण्युः १. ६८, १.

भुरण्युं १०. १२३, ६.

भुरण्यू इति १. १२१, ५.

भुरण्यू इति ६. ६२, ७.

भुरंत ५. ६, ७.

भुरंतु १०. ७६, ६.

भुरमाणं १. ११९, ४.

भुरिजोः ४. २, १४; ९. २६, ४; ७१, ५.

भुरिजोःऽइव ८. ४, १६.

भुरिषाट् ९. ८८, २.

भुर्वणि १. १३४, ५[२].

भुर्वणिः १. ५६, १.

भुवः १. ६९, १; ८६, ५; ४. २, ६; १६, १८[२]; १९, २; ५. १२, ३; ६. २२, ९; ७. ८, ५; ३२, ११; ८. १, २८; ६२, ७; ६६, ६; ७५, ३; ९२, ३०; १०. ४, १; ८, ५[३]; ६; ५०, ४[३]; १५३, ५.

भुवः १०. ७२, ४; ८८, ६.

भुवः १. ५२, १३; १३८, ४; ५. १९, ५; ८. २३, १८.

भुवत् १. ३६, ८; ६५, २; ६७, १; ६८, १; ७६, १; २. १, १५; १०, ३; २२, ४; ४. ७, २; १६, १०; ५. ९, ७; ६. १६, १८; ४८, २[२]; ७. ३१, ८; ३२, १३; ५०, २; ८. ७१, १५; ८२, ३; ९. ३४, ४[२]; ९२, ३; १०. २१, ५; २६, ९; १११, ३.

भुवत् १. ५, ३; २३, ६; ५२, ११; ६०, ४; ६१, १४; ७२, १; ११९, ७; २. २०, ६; ३. ६२, ९; ४. १, १६; ९, २; १६, ८; २३, २; ४; ३१, १; ८. १९, ३७; ३१, १५; ४६, १३; ९२, ६; ९३, ७; १५; ९. ४७, ३; ९७, २३; २४; १०२, १; १०. २३, २; ८६, ६.

भुवन् १. १८६, २; ७. ३१, ९; ८. २७, ४.

भुवन् ५. ४६, ६; ६. ३५, १; १०. ५०, ७; ११२, ७.

भुवनऽच्युवानां १०. १०३, ९.

भुवनं १. ७३, ८; १०२, ८; १०८, २; ४. ५४, ४; ५८, ११; ५. ६३, ७; ८१, ५; ८३, २; ६. ४७, ३; ७. ७६, १; १०. १७, १; २७, २२; ८८, २; १०७, ८; ११४, ४.

भुवनस्य १. १४३, ४; १६४, २१; ३४–३६; १८५, ५; २. २७, ४; ३१, ४; ३३, ९; ४०, १; ३. ४६, २; ४. ५३, २; ४; ५. ५१, १२; ६३, २; ८५, ३; ६. ३६, ४; ४९, १०; ७०, २; ७. ५१, २; ७५, ४; ८२, ५; ९५, २; ८. ३७, ३; ९. ३१, ६; ८५, ३; ८६, ५; २८; ३६; ९६, १०; ९७, ४०; ५६; १०. १७, ३; ३०, १०; ४५, ६; ६३, ८; ८८, ५; १२८, ७; १४९, ३; १६८, २; ४.

भुवनस्य ५. ६२, ९.
भुवना १. ८५, ८; ९२, ९; १०१, ६; १०९, ६; १६१, १२; १६४, २; २. १७, ४; २४, ५; ३४, ४; ३५, २; ४०, ५; ३. १६, ४; ६२, ९; ४. ६, ५; १६, ५; ६. ७, ६; ५८, २; ७. ५, ७; १३, ३; ८३, २; ८. ९२, ६; १००, ४; ९. ५४, ३; ६२, २७; ७३, ८; ८०, ३; ११०, ९; १०. २५, ६; ५६, ५; ६५, १५; ८२, ३; ८५, १८; १२५, ७; १४२, २; १५७, १.
भुवनात् १. १२३, २; १३४, ५.
भुवनानां १. ९८, १; ६. ७०, १; ८. ४१, ५.
भुवनानि १. ३५, २; ५; ६४, ३; १०८, १; ११३, ४–६; १५४, २; ४; १६०, २; ३; १६४, १३; १४; १६६, ४; २. ३, १; १०, ४; ३५, ८; ३. ३, १०; ५५, १०; १९; ६१, ३; ४. ४२, ३; ७; ५१, ५; ५३, ४; ५. ४०, ५; ६. ५, २; ७, ७; ७. ६१, १; ८०, १; १०१, ४; ८. ३, ६; १२, २८; ४२, १; ५१, ४; ९७, १४; ९. ७०, १; ८३, ३; ८४, २; ८६, ३०; ३७; ४६; ९४, २; ३; १०. ३७, ९; ७२, ७; ८१, १; ४; ८२, ३; ६; ८८, ९; ११; १६; ११०, ९; १२५, ८; १३९, १; १७०, ४.
भुवनाय १. ३१, २; ९२, ४; ५. ८३, ४; १०. ८८, १; १२.
भुवने १. ३५, ६; ६. ५८, २.
भुवनेन ८. ३५, २.
भुवनेभ्यः २. २३, १७; ८. ९६, १६.
भुवनेषु १. १५७, ५; १६४, ३१; ३. २, १०; ४. ५६, ३; ७. ३३, ७; ८. १०१, १४; ९. ८६, १४; ३८; ३९; ४५; १०. १२०, १; १८३, ३.
भुवं १०. ४८, १; ४९, १; ८६, ५; ११९, ८.
भुवा ३. ५५, १३.
भुवानि ७. ८६, २.
भूः ६. १५, १४; १०. ७२, ४; १४९, २.
भूः १. ३३, ३; ५२, १३; ९१, २; १७८, ५; १८९, ७; ६. १, ५; १५, ३; २०, ११; ३३, ४; ६४, ५; ७. १९, १०; २१, ६; १०. ११, ९; ४६, ५.
भूत १. ७१, ४; १७८, ३; २. ४, १; ५; १९, ४; ३. ३२, १२; ३६, १; ६. ४, २; १८, ८; ६७, ८; ८. २, ३७; ७१, ११; १०. ३, २; ९९, ३; ११; १०५, ९.
भूत १. ३८, ५; ६३, ६; ७३, २; ७७, ३; १००, ४; ११६, ६; १७३, ८; १७८, ४; २. १८, १; २९, ४; ३. ३२, ११; ५३, ३; ४. १७, ४; १९, ९; २५, ७; ४३, ४; ५. ४१, १६; ६. १८, १३; १९, १; २९, ४; ३०, २; ३४, २; ६१, १०; १२; ७. २०, २; ६२, १; ६८, ६; १००, ६; १०४, ७; ८. ७९, २; १०. ४, ७; २३, १; २९, ३; ४८, ९; १००, ६; १०५, १०.
भूत १. १०६, २; ४. ३७, ४; ७. ४८, ४; १०. ३०, २; ६१, २७.
भूत १. १६५, १३; ४. ३५, १; ६. ५०, ११; १५; ७. ५६, २२; ८. २०, २४; २७, २.
भूतऽअंशः १०. १०६, ११.
भूतः ८. २, ४०.
भूतः १०. २७, ७.
भूतन ७. ५९, १०; १०. ३०, ११.
भूतं १. ९३, ७; १८५, ११; २. ३२, १; ४. ४१, ५; ६. ६८, २; ७. ६७, ९; ९३, २; ९९, ३; ८. ९, ११; १०. ४०, ५; ५५, २; ५८, १२; ९०, २.
भूतं २. ३९, ६; ३. ५४, ३; ६. ६३, ५; ६८, ४; ७४, १; ८. ८, ९; २२, १६; १०. ४०, ५; ९३, १.
भूतस्य १०. ८५, १७; १२१, १.
भूतानां ३. २७, ९; १०. १७४, ५.
भूतानि १०. ८२, ४; ९०, ३; १३७, ५; १७४, ३.
भूतिं १. १६१, १.
भूतिं ८. ५९, ७.
भूतु १. ९४, १२.
भूतु १. १३१, ७[२]; १३६, ४; २. २, ५; १७, २; ३. १, २३; ४. ५०, ११; ५. ४२, १६; ६. ४५, ३०; ७. १०४, ६; ८. १, ३; ५, १८; २६, १६; ४४, २८; ४५, ३६; ७३, १; १०. ७०, ४; १५७, ३.
भूत्वा १०. १६२, ५[२].
भूत्वी ७. १०४, १८; १०. ८५, २९; १४५, ५.
भूथः ६. ६७, ५.
भूना १०. ८२, ४; १४९, ३.
भूम १. ६१, १४; ६२, ८; ६५, २; ७०, ३; ८५, ५; ८८, २; १५९, २; १७३, ६; २. ४, २; ७; ४. १७, ४; ५; २२, ३; ४२, ४; ५. ७, ५; ४५, ३; ८५, ३; ६. २०, १; ३६, ५; ५०, ५; ६२, ८; ७. ३४, ७; १९; ४५, १; ६९, २; ८६, १; ९. ९७, २३; १०. ३१, ९; १४२, ४.
भूम १. १०५, ३; ७. १९, ७; ४६, ४; ५७, ४; ६२, ४; ८. १, १३; १०. ३७, ६.
भूमऽइव ८. ३९, ७.
भूमनः ६. ७१, २; ९. ७३, ५; ७४, ७; १०१, ७.
भूमना १०. ३१, ६.
भूमना १. ११०, २.
भूमयः ८. ६, १५.
भूमानं १०. ९८, १२.
भूमिः १. ८७, ३; २. ११, ७; ४. १७, २; ५. ५९, २; ६. ४७, २०; ४८, २२; ७. ४, ५; ८. २०, ५; ९. ६१, १०; १०. ८५, १; ७; ९०, १४; १३२, १; ६.
भूमिं १. ५२, १२; ६४, ५; १६४, ५१; ३. ३०, ९; ४. २६, २; ५७, ८; ५. ५९, ४; ८४, १; ८५, ४; ६. ६७, ६; ८. १४, ५; १०. १८, १०; २७, १३; ५८, ३; ५९, ३; ८१, २; ९०, १; ५; १४२, ५.

भूमीः १. १०२, ८; २. २७, ८; ७. ८७, ५; ८. ४१, ९; ७०, ५.
भूमे १०. १८, ११.
भूम्यस्य ५. ४१, १०.
भूम्या १. १६१, १४; १०. ७५, ३.
भूम्याः १. ६२, ५; ८०, ४; १६४, ४; २. १४, ७; ७. ८३, ३; १०. १९, ८; ६८, ४; ७५, २; ११४, १०.
भूम्यौ १. ३९, ४; १६२, ११.
भूयः २. १४, १०; ५. ७९, १०; ६. ३०, १; ८. ५, २७; १५, ११; ५१, ७; १०. ११७, ८.
भूयःऽभूयः ६. २८, २.
भूयसः १. ३१, ६; १०२, ७; २. २, १२; ५. ३०, ४; ७. ८२, ६; ८. १७, १५.
भूयसा ३. १६, ६; ४. २४, ९².
भूयसीः १. ११, ८; १८८, ५; २. २८, ९.
भूयाः १. १६४, ४०; ६. ४७, २६; १०. ४३, ९; ९१, १३.
भूयाः १. १८५, ८; १८६, ११; १०. ३१, ५.
भूयाम १. १७, ४; ३. १९, ३; ८. ३, २.
भूयामो इति ४. ३२, ६.
भूयासं १०. १६६, ५.
भूयिष्ठः १. १६१, ९.
भूयिष्ठं ५. ७७, ४; ८. ९६, ३.
भूयिष्ठाः १. १६१, ९.
भूयिष्ठां १. १८९, १.
भूरयः १. ५५, ८.
भूरि १. १०, २; ३३, ३; ४८, २; ९; ५७, ५; ७३, ४; ८१, २²; ६; १०३, ५; १२०, १०; १२४, १२; १५४, ६; १६५, ७; १८५, ९; २. २९, ५; ३. १८, ४; ३१, ९; ३९, ८; ४४, ३; ५४, १५; ५७, १; ५८, ९; ४. ४, ९; ११, २; २०, १०; ३२, २०³; ५. ३, १०; २९, १४; ६. १, १२; १३, ५; ४७, १९; ७१, ४; ७. १, १७; ४, २; ८, ५; २२, ६³; ५६, २३; ८. ११, ५; १९, २०; २३, २१; ३२, ८; ४५, २; ३८; ४६, २५; ५५, १; ६२, १०; १२; ९०, ४; ९७, १५; १००, २; ९. ९१, ६; १०. ८, ९; ४२, ८; ४६, ३; ४८, ७; ७९, १; ८३, ७; १००, ७; ११३, ९; १२०, ५; ६; १२५, ३.
भूरिऽअक्षाः २. २७, ३.
भूरिऽआसुतिः ८. ९३, १८.
भूरिऽओजाः १०. १२०, २.
भूरिऽकर्मणे १. १०३, ६.
भूरिगो इति भूरिऽगो ८. ६२, १०.
भूरिऽचक्षसं ९. २६, ५.
भूरिऽजन्मा १०. ५, १.
भूरिऽदाः ४. ३२, २०.
भूरिऽदाः ४. ३२, १९; २१.
भूरिऽदात्रः ३. ३४, १.
भूरिऽदाभ्यः ९. ६६, १७.
भूरिदावत्ऽतरः ८. ५, ३९.
भूरिदावत्ऽतरा १. १०९, २.
भूरिऽदावरीं ८. २, २१.
भूरिऽदावा ९. ८७, ४.
भूरिऽदाव्नः २. २७, १७; २८, ११; २९, ७.
भूरिऽधायसं ९. २६, ३.
भूरिधारे इति भूरिऽधारे ६. ७०, २.
भूरिऽपाशौ ७. ६५, ३.
भूरिऽपोषिणः ३. ३, ९.
भूरिऽभारः १. १६४, १३.
भूरिऽभिः ८. ७०, १४; १०. ११, ५; ३८, ४.
भूरि १. १८५, २; ६. १६, ८; २०, ८.
भूरिऽरेतसा ३. ३, ११; ६. ७०, १; १०. ९२, ११.
भूरिऽवर्पसः १०. १४०, ३.
भूरिऽवर्पसा ३. ३, ४.
भूरिऽवारं ८. ५८, ३; १०. ४७, २.
भूरिऽवाराः ३. ५७, ४.
भूरिऽशृंगाः १. १५४, ६.
भूरिषु ८. ४५, ३४.
भूरिऽस्थात्रां १०. १२५, ३.
भूरीणि १. १६५, ७; १६६, १०; ३. १९, ४; २०, ३; ४. १७, १९; ७. १९, ४.
भूरेः १. ६१, १५; ९६, ७; १८४, ३; २. २८, १; ३०, ५; ३३, ९; १२; ३. ३६, १०; ३९, ८; ६. १३, २; ६०, १; ७१, ६; ७. ४, ६; २१, ८; ६०, ५; ९३, २; ९५, २; १००, २; ८. ३२, १४; ४५, ४२.
भूर्णयः १. ५५, ७; ८. २५, १५; ९९, १; ९. १५, ३; १७, १; ४१, १; ७३, ४.
भूर्णये ७. ८६, ७; ९. ५१, ४.
भूर्णिः १. ६६, १; ७. ८७, २.
भूर्णि ३. ३, ५; ८. १, २०; १७, १५.
भूवन् १. १३९, ८; ६. ६६, २; १०. २२, १२.
भूष १. १५, ४; ७. ९२, १; ८. ९६, १२.
भूषत १. १८२, १; ८. ६६, ७; ९. १०४, १.
भूषतः ६. ६२, ४.
भूषतं ७. ७४, ३; १०. १४३, ६.
भूषति ८. २२, ५.
भूषति १. ४६, १२; ३. ३, २; ५. ७५, १; ८. ६६, ८; १०. ११, ७; ४०, १.
भूषतु ८. ९०, १.
भूषथः ३. १२, ९; ३८, ६; ५. ७५, ८.
भूषन् १. १४०, ६; ३. २५, २; ३४, २; ९. ९४, ३.
भूषन् १. १५१, ३.
भूषन्ऽइव १०. ४२, १.
भूषन्ति १. ९५, ३; १६२, १३; ८. ९९, २; १०. १०४, ७.
भूषसि ८. ९२, २६.
भूषसि १. ३१, २.
भूषात् ४. १६, ११.
भूषेम ३. ३, ९.
भृगवः १. ५८, ६; १२७, ७²; १४३, ४; २. ४, २; ४. ७, १; १६, २०; ६. १५, २; ७. १८, ६; ८. ३, १६; ६, १८; ९. १०१, १३; १०.

१४, ६; ३९, १४; ४६, २; ९; ९२, १०; १२२, ५.

भृर्गवाणः १. ७१, ४.

भृर्गवाणं ४. ७, ४.

भृर्गवाणे १. १२०, ५.

भृर्गवे १. ६०, १; ८. ३, ९.

भृर्गुऽभिः ८. ३५, ३.

भृर्गुऽभ्यः ३. ५, १०.

भृ॒गु॒ऽवत् ८. ४३, १३.

भृर्गूणां ३. २, ४.

भृ॒ज्जाति॑ ४. २४, ७.

भृ॒तिं ८. ६६, ११; ९. १०३, १.

भृ॒त्यां १. ८४, १६.

भृ॒त्यै १०. २९, ४.

भृ॒थे २. १४, ४.

भृ॒मं ८. ६१, १२.

भृ॒मर्यः ३. ६२, १.

भृ॒मात् ७. १, २२.

भृर्मिः १. ३१, १६; ४. ३२, २.

भृर्मि २. ३४, १; ७. ५६, २०.

भृ॒ष्टिः १. ५६, ३.

भृ॒ष्टि॒ऽमता॑ १. ५२, १५.

भे॒जा॒ते॒ इति॑ ७. ३९, १.

भे॒जा॒नासः ४. २९, ५; १०. १५३, १.

भे॒जि॒रे ७. १, ९.

भे॒जि॒रे॒ ५. ५७, ५; १०. ९४, ८.

भे॒जे ७. १८, १६.

भेत् १०. ६८, ६.

भे॒त् १. ५९, ६; १०४, ८[२]; ७. १८, २०.

भे॒त्ता ८. १७, १४.

भेर्दति ८. ४०, १०; ११.

भे॒दु॒ति॒ ५. ८६, १.

भे॒दं ७. १८, १९; ३३, ३; ८३, ४.

भे॒दस्य॑ ७. १८, १८.

भे॒दी ९. ११२, ४.

भे॒म॒ १. ११, २; ८. ४, ७.

भे॒ष॒जः २. ३३, ७.

भे॒ष॒जं १. २३, १९; २१; ८९, ४; ५. ५३, १४; ८. ९, १५; २०, २५; ७२, १७; १०. ९, ५; १००, १०; १३७, ३; ६; १७५, २; १८६, १.

भे॒ष॒जस्य॑ ५. ४२, ११; ८. २०, २३.

भे॒ष॒जा १. २३, २०; ३४, ६; ११४, ५; २. ३३, १२; १३; ७. ४६, ३; १०. ५९, ९.

भे॒ष॒जानि॑ ६. ७४, ३.

भे॒ष॒जीः १०. १३७, ६.

भे॒ष॒जेभिः १. १५७, ६; २. ३३, २; ४.

भोगं १. १६३, ७; ३. ३४, ९; १०. ३४, ३; ५९, ६.

भो॒गान् ५. २९, ६.

भो॒गैः ६. ७५, १४.

भो॒जः ८. ७०, १३; १०. १०७, ११; ११७, ३.

भोर्जते १. ७२, ८.

भो॒ज॒न् १. ४४, ५.

भोर्जनं १. ८३, ४; २. १३, २; ४; ६; २६, १; ३. ४४, ३; ५. ३४, ७; ८२, १; ७. ६८, ५; ७४, २; ८. १, ३४; १०. २३, ६; ४८, १.

भोर्जना ४. ३६, ८; ७. १८, १५; १७; ९. ८७, ६; १०. ४४, ७.

भोर्जनानि १. १०४, ८; ५. ४, ५; ७. ५, ३; १९, ६; १०. १३१, २.

भोर्जनाय ३. ३०, १४; ५. ८३, १०.

भो॒जं २. १४, १०; १७, ८; ४. ४५, ७; ८. ३, २४; १०. ४२, ३; १०७, ११[२].

भो॒जं॒ २. २८, ९.

भोर्जसे १. ५५, ३; ८. ५१, ३; ६५, ३.

भो॒जस्य॑ ७. १८, २१; १०. १०७, १०.

भो॒जाः ३. ५३, ७; १०. १०७, ८[२]; ९[४].

भो॒जान् ४. ५१, ३; ५. ५३, १६.

भो॒जाय॑ १०. १०७, १०[२].

भो॒जेषु॑ ८. २५, २१; १०. १५१, २; ३.

भो॒ज्यं॑ ८. २१, ८.

भो॒ज्या॑ १. १२६, ६; १२८, ५[२].

भ्र॒मः ६. ६, ४.

भ्र॒माः ९. २२, २.

भ्र॒मासः ४. ४, २.

भ्र॒शा॒त् १०. १७३, १.

भ्रा॒जः १०. १७०, ३.

भ्राजत्ऽऋष्टयः १. ३१, १; ६४, ११; ८७, ३; १६८, ४; ५. ५५, १; १०. ७८, ७.

भ्रा॒ज॒त्ऽऋ॒ष्ट॒यः २. ३४, ५.

भ्राजंत्ऽऋष्टिं ६. ६६, ११.

भ्राजंते १०. २०, ३.

भ्रा॒ज॒ते १. ५६, ३; ५. ६२, ७.

भ्राजंत्ऽजन्मानः ६. ६६, १०.

भ्राजंतः १. ५०, ३; ५. १०, ५; ८. ४४, १७.

भ्राजंती १. १६२, १५.

भ्राजंते १. ८५, ४; ७. ५७, ३; ८. ३४, १७.

भ्रा॒जं॒ते १. ४४, १२; ७. ५५, २; ८. २०, ११; १०. १४०, १.

भ्राजंमानः ७. ६३, ४; १०. ८८, १६.

भ्राजंमानं ९. ५, १०.

भ्राजंसा १०. ७८, २.

भ्रा॒ज॒से ९. १७, ५.

भ्रा॒जा ९. ९८, ३.

भ्राट् १०. १२३, २.

भ्रा॒तः १. १६१, १; ३; १७०, ३; ३. ५३, ५; ६. ५१, ५.

भ्रातंरः १. १७०, २; ५. ६०, ५; १०. ३४, ४; ५१, ६.

भ्रातंरं ४. १, २; ५. ३४, ४; ८५, ७; १०. ७, ३.

भ्रातंरा ६. ५९, २.

भ्रा॒तरिति॑ ८. ४३, १६.

भ्राता॑ १. १६४, १[२]; १९१, ६; ६. ५५, ५; १०. १०, ११; १२; ११, २; १६२, ५; १८६, २.

भ्राता॑ऽइव १. ६५, ४.

भ्रातुः ४. ३, १३; ८. १, ६; १०. ५५, १; ९९, २.

भ्रा॒तृ॒ऽत्वं ८. २०, २२; ८३, ८; १०. १०८, १०.

भ्रा॒त्रं ४. २३, ६; २५, २.

भ्रा॒त्रा ४. १०, ८.

भ्रा॒त्राय॑ २. १, ९.

भ्रा॒शयंन् १०. ११६, ५.

भ्राश्यानि १०. ११६, ५.

भ्रि॒यं॒ते १. १४, ४; ७. २१, २.

भ्रि॒या॒ते ५. ३१, १२.

भ्री॒णंति॑ २. २८, ७.

भ्रु॒वोः ४. ३८, ७.

भ्रू॒णानि॑ १०. १५५, २.

भ्रे॒ष॒ते ७. २०, ६.

म

मंश्रुतोः ७. ४४, ३.
मंसते १. ८४, १७; १८; ५. ४६, ४; ८. ६२, ११.
मंसँते ७. ३४, ३.
मंससे १०. २७, १०.
मंसि ७. ८८, २.
मंसीमहिं १. १३६, ७; ६. १९, ७; १०. २६, ४.
मंसीरत १०. ३७, ५.
मंसीष्ट ७. ३८, ६.
मंसीष्ठाः १. १७५, ५.
मंसैं १०. ११३, १०.
मंहते ६. ४५, ३२; ८. ५०, १; १०. ६२, ८.
मंहते १. ११, ३; ९. १, १०; १०. ६२, ६.
मंहना ३. ३१, १७; ४. १७, १; ५. १०, २; १६, ४; १८, २; ६१, १०; ६. ६४, ५; ६७, ५; ७. ८१, ४; ८. २६, २४; ९. ३७, ६; ७०, २.
मंहनाऽइव ४. १, ६.
मंहनेऽस्थाः १०. ६१, १.
मंहमानं ८. २४, २२.
मंहय ५. ३८, १.
मंहयत्ऽरयिः ९. ५२, ५; ६७, १.
मंहयं १०. ४८, ९.
मंहयुः ९. २०, ७.
मंहसे ८. ५२, ६.
मंहसे ४. ३१, ८; ८. ६१, ८; ९. ८२, ४.
मंहिष्ठः ४. ३१, २; ८. ४, १८; १५, १०; १९, ३६; ४६, २४; ८८, ६; ९७, १३; ९. १, ३; १०. १७२, २.
मंहिष्ठं १. ३०, १; ५१, १; ६१, ३; १३०, १; ५. ३९, ४; ६. ४४, ४; ८. १, २; १६, १; ९२, १; ९. १०२, ६; १०. ३३, ४.
मंहिष्ठऽरातिं १. ५२, ३.
मंहिष्ठस्य १. १४७, २.
मंहिष्ठा ४. ४१, ७; ६. ६८, २; ८. ५, ५; २२, १२; १०. १४३, ६.
मंहिष्ठाः १. १२१, १५.
मंहिष्ठाभिः ८. २३, २३.
मंहिष्ठां १०. १०४, ५.
मंहिष्ठाय १. ५७, १; ८. १०३, ८.
मंहिष्ठासः ८. १, ३०.
मंहीयान् ९. ६६, १७.
मक्षः ४. ४५, ४; ७. ३२, २.
मक्षा १०. ४०, ६.
मक्षिका १. ११९, ९; १६२, ९.
मक्षु १. २, ६; ३९, ७; ५८, ९; ६०, ५; ६१, १६; ६२, १३; ६३, ९; ६४, १५; २. १३, १; ४. १६, १६; २१, ३; ४३, ३; ६. ६६, ५; ७. ५६, १५; ८. २२, १०; २७, १०; ३१, १५; ३३, ३; ६१, ४; ८१, ९; ८८, २; ९. ८८, ७; १०. २२, ११; ६१, ९; १०; २०; १४७, ४.
मक्षुंऽगमाभिः ८. २२, १६.
मक्षुजवःऽतमा ६. ४५, १४.
मक्षुऽतमस्य ८. १९, १२.
मक्षुऽतमेभिः ९. ५५, ३.
मक्षुऽभिः ८. २६, ६.
मक्षुऽमक्षु ३. ३१, २०.
मक्षुयुऽभिः ७. ७४, ४.
मखः १. ६, ८; १३८, १²; ६. ७१, १; ९. २०, ७; १०. ११, ६.
मखं ९. १०१, १३.
मखस्य १. १३४, १; ३. ३४, २; ८. ७, २७; १०. १७१, २.
मखस्यते ९. १०१, ५.
मखस्यन् ३. ३१, ७.
मखस्यसे ९. ६१, २७.
मखस्युं १०. ७३, ७.
मखस्युवः ९. ५०, २.
मखस्युवं ९. ६४, २६.
मखा १. ६४, ११; ११९, ३.
मखाय ८. ४६, २५.
मखेभ्यः ६. ६६, ९.
मघत्तये ४. ३७, ८; ५. ७९, ५; ८. २४, १०; ४५, १५; ७०, ९; १०. १५६, २.
मघऽदेयं ७. ६७, ९.
मघऽदेयाय १०. ४२, २.
मघं १. ११, ३; १४१, ९; ३. १३, ३; ४. ३२, ८; ८. १४, ४; २१, १७; ९. ७५, ५; १०. १४७, ३.
मघवत्ऽतम ८. ५४, ५.
मघवत्ऽत्वस्य ६. २७, ३.
मघवत्ऽभिः ४. १६, १९.
मघवत्ऽभ्यः १. ५८, ९; १२४, १०; २. ३३, १४; ३५, १५; ६. १०, ५; ४६, ९; ७. १, २०; २५; ५, ९; ७, ७; १६, ९; २४, ६; ५८, ३; ६७, ९; ७४, ५; ९५, ३; ८. ५, १२; ९. २०, ४; ३२, ६; ९७, ५५.
मघवत्ऽसु १. ६४, १४; ९३, १२; १२३, १३; १४०, १०; ७. ३७, २; ८. ५०, २; १०. ३९, २; ९३, १४.
मघंऽवन् १. ८२, १; ३; ४. ३०, ७; ८. २४, ११; ३२, ८; ६१, १३; ६२, १०; ६६, १३; ८९, ५.
मघऽवन् १. ३३, १२; १५; ५२, ११; ५४, १; ५७, ५; ५८, ९; ८४, १९; १०२, ३²; ४; ७; १०; १०४, ५; ८; १२१, १५; १२७, ११; १३२, १; १३३, ३; १६५, ९; १७८, ५; २. ३६, ५; ३. ३०, ५; १६, २१; ३१, १४; १९; ३२, १; ३६, १०; ४३, ५; ४७, ४; ५३, २; ४; ५; १४; २१; ६०, ५; ४. १६, ९; १९; १७, ७; १८, ९; २२, १०; २९, ५; ५. २९, ५; १३; ३०, ७; ३१, ६; ३३, २; ३६, ३; ४; ४२, ६; ६. १५, १५; २३, १; २७, ३; ४४, १०; १७; १८; ४६, ८; १०; ४७, ९; ७. १८, २; १९, ८; ९; २०, ९; २२, ३; ६; २७, २²; २९, १; ३; ४; ३२, ७; १४; १९; २१; २३–२५; ३७, ३; ४१, ४; १०४, १९; ८. १, ४; ३, १४; १७; १८; ४, ४; १०; २४, १०; ३३, ३; ११; ३६, २; ४५, ६; ४६, ११; ४९, ९; १०; ५१, १; ६; ७; ५२, ८; ५३, १; ५४,

७; ६१, ४; ७; १४; ७०, ६; ९; ७८, १०; ८८, ६; ९०, ४; ९३, १०; ९७, १; ८; १००, ६; १०. २८, ३; ५; ३३, ३; ४२, ३; ४३, ५; ४४, ९[२]; ५४, १; ४; ५; ५५, १; १००, १; १०२, ३; १०३, १०; १११, ६; ११२, ९; १०; ११६, ७[२]; १३१, ५; १३४, ६; १४७, ३–५; १६७, ३.

मघऽवां १. ३२, ३; १३; ५५, ४; १०३, २; ४; १४६, ५; १५७, ३; १७१, ३; १७३, ५; १७४, १; ७; २. ६, ४; ३. ३०, ३; ५३, ८; ४. १७, ८; ९; ११; १३[२]; १९; २०; २०, २; २२, १; २४, २; २७, ५; ४२, ५; ५. २९, ६; ८; ३०, ३; ३१, १; ३४, २; ३; ८; ६१, १९; ६. २४, १; २७, ८; ४७, ११; १५; ५८, ४; ७. २७, ४; ९८, ५; ८. १, १२; २१, १०; ३३, ९; १३; ४६, १३; ४९, १; ५२, ५; ६१, १; १८; ६५, १०; ७०, १५; ९६, २०; १०३, ९; ९. ८१, ३; ९६, ११; ९७, ५५; १०. २३, २; ३; ३३, ८; ४२, ६; ८; ४३, ३; ५; ६; ८; ४९, ११; ८१, ६; ११३, २; १६०, ४.

मघऽवान् ४. १६, १.

मघऽवानः १. ७३, ५; ८; ७७, ४; ९८, ३; १३६, ७; १४१, १३; ५. ४२, ८; ७९, ६; ७. १६, ७; २०, १०; ६०, ११; ७८, ५; १०. २७, ४.

मघऽवानः ७. ४८, १; १०. ३२, ९.

मघऽवानं ३. ३०, २२; ५१, १; ४. ३१, ७; ७. २६, १; २; २८, ५; ८. ९७, १३; १०. ४३, १; ७४, ५; १०४, ७; १६७, २.

मघऽवाना ८. २६, ७.

मघऽवाना १. १८४, ५; २. २४, १२; ३. ५८, ५; ४. २८, ५.

मघस्यं ४. २०, ७; ८. १, ३०; ८८, ६.

मघा ५. ३२, १२; ६. ३७, ४; ७. १६, १०; ९. १, १०.

मघाऽइंव १. १०४, ५.

मघानां ७. २६, ४.

मघानिं ३. १९, १; ५३, ७; ४. १७, ८; ५. १०, ३; ३०, १२; ६. १२, २; ७. १९, १०; २१, ७; २९, १; ३०, ४; ५७, ६; ६७, ९; १०. ३२, ९; ७३, ४; १३२, ३.

मघायं ७. २७, ५.

मघैः ५. ७९, ४; ८. २४, २; १०. २३, २.

मघोनः १. ३१, १२; ५४, ११; १४०, १२; २. २७, १७; २८, ११; २९, ७; ४. १७, ५; ५. १६, ३; २७, १; ३१, ९; ६५, ६; ६. २३, १०; ४४, १२; ७. १२, २; ३२, १५; ८१, ६; ८. २, १३; ३३; २४, २; ९. ८, ७; ३२, १; १०. २२, १५.

मघोनां १. ४८, २; ५. १८, ३; ५; ३९, ४; ६४, ४; ५; ६. ३७, ४; ६८, २; ७. ३२, ७; ५८, ६; ९६, २; ८. १, १६; ३०; २, ३४; १९, ३४; ५३, १; ९४, १; १०३, ७; ९. १, ३; ८०, २; १०. ९३, ९.

मघोनि १. ११३, १७; १२४, १०[२]; ३. ६१, १; ४. ५५, ९; ५. ७९, ४; ६; ७; ६. ६५, ६; ७. ७७, ४.

मघोनीं १. ४८, ८; ११३, ५; १३; २. ११, २१; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; ३. ६१, ४; ६. ६४, १; ७. ७५, ५; ७८, ४; ७९, ३.

मघोनी इति ७. २, ६.

मघोनीः ४. ५१, ३; ६. ६५, ३.

मघोनोः ५. ८६, ३.

मज्जंति ९. ६४, २१.

मज्जाने १०. ६८, ९.

मज्मना १. ५१, १०; ५५, ५; ६४, ३; ८४, ६; ११२, ३; ४; १७; १२८, ५; १३०, ४; १४१, ६; १४३, २; ४; २. १, १५; १७, ४; २२, २; ३. ४६, ३; ६. १८, ७; ७. ८२, ५; ८. ८८, ४; १०३, २; ९. ११०, ९; १०. २९, ६.

मणिऽग्रीवं १. १२२, १४.

मणिनां १. ३३, ८.

मंडूकः ७. १०३, ४; ९. ११२, ४.

मंडूकाः ७. १०३, १; १०; १०. १६६, ५.

मंडूकाः ७. १०३, ७.

मंडूकाःऽइव १०. १६६, ५.

मंडूकानां ७. १०३, २.

मंडूक्यां १०. १६, १४.

मंडूरऽधाणिकीः १०. १५५, ४.

मत् २. २८, ५; ६; २९, १; ५. २, ८; ६. ६७, २; १०. १०, ८; १०; १२; ८६, ६[२]; ९५, ८; १६६, ३.

मतयः १. ६२, ११; १६५, ४; १८६, ७; ३. ४१, ५; ४३, २; ५. ८७, १; ६. १०, २; ७. १०, ३; ९. ७२, ६; ८५, ७; ११; ८६, ३१; ४६; ९५, ४; ९७, ३४; १०६, ११; १०. ७, २; ४३, १; ९१, १२; १११, १.

मतऽवचसा १. ४६, ५.

मतऽवान् ९. ८६, १३.

मतंस्नाभ्यां १०. १६३, ३.

मतिः १. १४१, १; १४२, ४; ३. ३९, १; ५५, ८; ५. ४४, ९; ५७, १; ६७, ५[२]; ६. ८, १; ७. ६६, ८; १०४, ६; ८. ६, ३४; १८, ७; ७४, ७; ९. ६९, १; २; १०. ३३, २; ४७, ६; ११९, ४.

मतिऽभिः १. ६०, ५; २. १८, १; २३, ६; १०; ३. ३०, २०; ४३, ३; ४. ३, १६; ५. ८०, १; ६. ५, १; २२, २; २३, ६; ३४, ५; ७. १२, ३; ३७, २; ३९, ६; ६९, ६; ७७, ६; ७८, २; ८. ९, ६; २३, २३; ९. ६८, ७; ७५, ४; ८४, ५; ८६, २४; ९६, १५; ९७, ३२; ३५; १०३, १; १०५, २; १०७, २४; १०. ६, ५; ७, २; ६४, १५; १६; ६७, ९; ८८, ५; १२३, १.

मतिं १. ६, ६; ३३, १३; ५७, १८ १०५, १५; १३६, १; १४३, १;

२. २४, १; ३. २६, ८; ७. ४, १; ८८, १; १००, २; ८. ६, ३१; ३२; ९, १६; ५९, ६; ९. २१, ७; ३२, ३; १०७, १८; १०. २५, १०; ९१, ८; १४; ११९, ५.

मती १. ८२, २; १६५, १; २. २४, ९; १३; ८. ६, ३९; २५, २४; ५१, ३; ९. ७, ६; २०, ३; ४४, २; ६३, २१; ६४, १०; ७१, ३; ७२, १; १०. ११, ६.

मतीः १. ११४, १; ७. २९, ३; ९. ७२, ५; ९५, १.

मतीनां १. ४६, ५; ७; ६१, ३; ८६, २; १८४, २; ३. ५, ३; ४६, ४; ४९, ३; ४. ३२, १५; ५. ४३, ९; ६. १७, २; ४४, २; ६९, २–४; ७. १३, १; ९. १०, ६; ७६, ४; ८६, १९; ९६, ५; ९७, ३७; १०३, ४; १०. २६, ४.

मतुर्थाः ९. ७१, ५.

मते ८. ६८, २.

मतऽकृतानि २. २८, ९.

मत्या ५. ५८, ५.

मतऽसंखा १०. ८६, १.

मत्संत ६. ४४, १६.

मत्सुत ४. ३१, २; ५. ४०, ४.

मत्सुत ९. ८५, १.

मत्सुति ८. ९४, ६.

मत्संथ १. १८६, १.

मत्सरः १. १७५, १; २; २. ४१, १४; ९. १३, ८; १७, ३; २७, ५; ३४, ४; ६३, २४; ६५, १०; ६६, ७; ७२, ७; ८६, १०; २१; ९६, ८; १३; ९७, ११; १०७, २३.

मत्सरं ९. २६, ६; ३०, ६; ४६, ४; ६; ५३, ४; ६३, १०; १७; १०. ३०, ९.

मत्सरऽवान् ९. ९७, ३२.

मत्सरस्यं १. १२५, ३.

मत्सराः १. १४, ४; १३७, १[२]; ९. १०७, २५.

मत्सराणि ७. ७३, ४.

मत्सरासः १. १५, १; ६. १७, ४; ९. २१, १; ६९, ६; १०७, १४.

मत्सरिन्ऽतमः ९. ६३, २; ६७, २; ७६, ५; ९९, ८.

मत्सि १. ९, १; १७५, १; १७६, १; ९. ९०, ५; ६; ९७, ४२[५].

मत्स्यं १०. ६८, ८.

मत्स्यासः ७. १८, ६.

मत्स्व १. ९, ३; ३. ४१, ८; ८. १, २३; ३, १; ६, ३९; १३, १४; ९२, ३०; ९९, २.

मत्स्व २. ४१, १७; ३. ६०, ५; ६; ४. ३२, १४; ८. ५४, २; १०. १२२, ५.

मथायत ९. ७७, २.

मथायति १. १४१, ३.

मथायन् ५. ३०, ८; ६. २०, ६.

मथितः ६. ४८, ५.

मथितं ३. ९, ५; ८. ४८, ६.

मथीः १. १२७, ११.

मथीत् १. ७१, ४; १४८, १.

मथीनां ८. ५३, ८.

मभ्रंतः १. १२७, ७.

मभ्रा १. १८१, ५.

मथ्यमानः ५. ११, ६.

मथ्राः ८. ४६, २३.

मद् १०. ६३, ३.

मदः १. ४, २; ८०, २; ८६, ४; १२७, ९; १७५, १; २; ५; ४. ४९, १; ५. ४०, २; ४४, ११; ६. १९, ७; २४, १; ३३, १; ४४, १; ७. २२, २; ८. १२, १; ४६, ८; ९२, १६; १७; ९. १७, ३; २५, १; २७, ५; ६१, १९; ६२, १४; ६३, १६; २२; ६४, २; १२; ६८, ३; ६९, ३; ७९, ५; ८०, २; ८५, २; ८६, ३५; ४२; ४६; ९७, ६; ९९, ३; १०५, २; १०७, १७; १०८, १[२]; १०. २५, १०; २९, ३; ९३, ८.

मदुऽच्युत् ९. १२, ३.

मदऽच्युतः ९. ९८, ३.

मदुऽच्युतः १. १२६, ४; ९. ३२, १; ७९, २.

मदुऽच्युतं १. ५१, २; ८५, ७; ८. १, २१; ७, १३; ९६, ५; ९. ५३, ४; १०८, ११; १०. ३०, ९.

मदुऽच्युता १. ८१, ३; ८. ३३, १८; ३४, ९.

मदुऽच्युता ८. २२, १६; ३५, १९.

मदुऽच्युति ८. ७४, १३.

मदंत १. १८२, १.

मदुत १. ५१, १.

मदुतां १. १२१, ११.

मदंति ४. २९, २; ३८, ३.

मदुति ८. १५, ९.

मदंथ ४. ३४, ११; ५. ५४, १०; ८. ७, २०.

मदंथः १. १०८, ७; ८. २६, १७.

मदंन् ६. १८, १४.

मदंन्ऽइव ८. १४, १०.

मदंतः १. १८५, ९; ३. ५३, १०; ५४, २०; ५९, ३; ४. ३३, १०; ५०, २; ६. ४४, २०; ७. ५९, ७; १०. ६८, १; १६५, ५.

मदंतं ३. २६, ९; ५. ३२, ४.

मदंता १. १८४, २; ५; ३. ५३, १; १०. १४, ७.

मदंति १. ८४, १०; ८५, १; १५४, ४; ५; १७३, ८; १८४, ४; ३. ६, ८; ५. ५२, १; ६१, १४; ७. ४९, ४; ९७, १; ८. २९, ७; ४६, ३२[२]; १०. १४, १०; १२०, १.

मदुंति १. १०९, ३; १६२, ७; ३. ४, ७; ७, ७; ३४, ८; ४. १७, ५; ७. ५७, १; १०. १४, ३; ७३, ८; ८२, २.

मदंती ५. ५६, ३; १०. १७, ८.

मदंती इति ३. ५४, ६.

मदंसीः ७. ६, ४; ४७, ३; १०. १२४, ८.

मदुंस्तु ६. ७५, १८.

मदुपती इति मदऽपती ६. ६९, ३.

मदे १. ८४, ४; ३. ४२, २; ४. २६, ६; ३३, ११; ६. ४३, २; ८. १, २१; १५, ४; ४५, २२; ९. ६, २; ३; ९; २३, ४; ४६,

६; ४८, २; ७८, ४; १०४, २; १०६, ५; १०७, १४; १०. ९६, १; १०४, २; १४४, २^{2}; १४७, ४.

मदंऽवृद्धः १. ५२, ३.

मदंस्य २. १६, ६; ५. ३२, ५; ६. ३७, २; ८. ५, १४; ९. २३, १; १०. ९६, ९.

मदाः १. ५३, ६; ४. ३४, १; २; ६. १७, ४; ७. २३, ५; ८. १४, १०; १६, ४; ४९, ३; ९. ७५, ५; ८६, १; १०१, ४.

मदानां ४. ३१, २; ८. ९२, ६; ९. २३, ७.

मुदानां ६. ६९, ३; ८. ९३, ३१; ९. १०४, ५.

मुदामः ९. १०७, २.

मदामसि ९. ११०, २.

मदाय १. १६, ८; ३०, ३; ३७, १५; ८१, १; १०४, ९; १०९, ४; ११७, १; १३०, २; १३५, १; ५; २. १८, ६; १९, १; ३४, ५; ३. ३२, २; १०; १५; ३५, १; ४७, १; ४. २१, ७; २७, ५^{2}; ३४, ४; ३५, ४; ६; ३७, ४; ४९, २; ५. ४३, ३; ५; ६; ६. ४०, १; २; ४४, १९; ७. २४, ३; ३२, ४; ९०, १; ९७, १; ८. १, २६; ९, १७; ३३, १५; ३६, १; ४६, ७; ६४, १२; ६६, ६; ८२, ५; ९५, ३; ९. २, ७; ८; ६, ६; ८, ५; १०, ४; ११, ८; १६, १; ३८, ३; ४३, १; ४५, १; ३; ५१, ४; ६२, ४; २०; ६६, २९; ८८, १; ९०, ५; ९६, ९; ९७, ५; १०; ११; १५; १९; १०१, ८; १०५, १; १०६, ८; १०७, ९; १०९, ११; १३; २०; १०. ४४, १; ११२, ५.

मदासः १. २०, ५; ४. १७, ६; ३५, १; ६. ३६, १; ९. ६९, ७; ८६, २.

मुदिन्ऽतम १. ९१, १७; ९. २५, ६; ५०, ५; ७४, ९.

मुदिन्ऽतमः ८. ६४, ११; ९. ८०, ३; ८५, ३; ८६, १०; ९६, १३; ९९, ६; १०८, ५; १५; १०. १३६, ६.

मुदिन्ऽतमं ८. १, १९; १३, २३; ९. १५, ८.

मुदिन्ऽतमस्य ९. ६२, २२.

मुदिन्ऽतमाः ९. ६७, १८.

मुदिन्ऽतमासः ९. ८६, १.

मुदिन्ऽतरं ८. २४, १६.

मुदिरः ९. ९६, २१; ९७, १५; १०७, १२.

मुदिरं २. १४, ९; ५. ६१, ११; ६. १७, ११; २०, ६; ८. ३८, ३.

मुदिरस्य १. १६६, ७; १०. ११२, ६.

मुदिराणि ६. ६९, ७.

मुदिरासः ८. ५३, ४; ९. ८५, ७; ८६, २.

मुदिरे ८. २१, ५.

मुदिरेण १०. ९४, ४.

मुदिष्ठ ९. ६, ९.

मदिष्ठः ६. ४७, २.

मदिष्ठया ९. १, १.

मदिष्ठाः ४. १७, ६.

मदे १. ४६, १२; ५२, ५; १०; १४; ५६, ३; ५; ६; ८०, १; ८५, १०; ११९, ९; १२१, ४; १७३, ७; २. १५, १–९; १७, १; ३. ४३, ७^{2}; ४. २६, ७; ५. २, १०; ५३, ३; ६. २७, १^{2}; ४३, १; ३; ४४, १४; ६९, ५; ७. ३७, १; ८२, ३; ८. १, २१; ३, ८; ७, १२; १४, ७; १७, ८; ३२, १; २८; ३३, ४; ४८, ६; ६६, २; ९२, १६; ९३, ८; १०. २१, १; ४४, ८; ५०, ७; ९६, ६.

मदेन ८. १, २१; ९. ७, ७; ९८, ७.

मदेभिः ४. ३५, ९.

मदेम १. ३०, १३; ६. ४, ८; १७, १५; ७. १, २४; १०. १३१, १.

मुदेम १. ९१, २१; ३. ५८, ६; ४. १६, १९; ४२, १०; ५. ३६, २; ४९, ५; ६. १९, १३; ४९, १३; ५२, १४; ७. १९, ८; ६४, ३; १०. ६७, ९.

मदेऽमदे १. ८१, ७; ८. १३, ७; १०. १२०, ४.

मदेऽरघुः ८. १०१, ३.

मुदेरिति मदेः ८. ९२, १६.

मुदेरू इति १०. १०६, ६.

मदेषु १. १३१, ५; १३४, ५; ७. २०, ४; २१, १; ८. ४६, १४; ९. १, १०; १८, १; ६१, १; १०. ११२, ४; १२०, २.

मद्यः ४. २२, ८; ९. ३८, ५; ८६, ३५.

मद्यं २. १४, १; ६. ६८, १०; ७. ९२, १; ९. ६, २; २३, ४; ६५, १५; १०७, १४.

मद्यानि ७. ६८, २.

मद्याय ८. २, २५.

मद्यासु १. १५३, ४.

मुद्रिक् १. १७७, १; ३; ६. ३१, ५.

मुद्र्यक् ३. ४१, १; ६. ३८, २.

मुद्रीचं ७. २४, ३.

मुद्र्युद्रिक् ६. २२, ११.

मद्वने ८. ९२, १९.

मद्वा ९. ८६, ३५.

मधुं १. १४, १०; १५, ११; १९, ९; २५, १७; ९०, ६^{2}; ७^{2}; ११२, ११, २१; ११६, १२; ११७, २२; १६६, २; १९१, १०–१३; २. ३६, ४; ६; ३७, २; ३९, ६; ३. ३१, ११; ३९, ६; ५३, १०; ४. १८, १३; ४३, ५; ५. ६१, ११; ६. ११, ३; ६०, १५; ७०, ५; ८. ५, ११; ७, १०; ८, १; ३; ४; १०, ४; १७, ५; २४, १३; २६, २०; ३३, १३; ३८, ३; ४८, १; ६५, ८; ६९, ६; ७२, ११; ९७, ८; ९. १, ८; २, ३; ११, ५; १८, २; ३९, ५; ६२, २०; ६७, ११; ३२; ६९, २; ७०, ८; ७२, २; ७४, ३; ७५, २; ८५, ४; ८६, १०; २०; ४८; १०७, ५; १०. २३, ४; ३२, ५; ४०, ६; ४९, १०; ६८, ८; ७३, ९; ७६, ६; ९४, ३; ४; ९; १०६, ८; १०;

११; १२०, ३; १३८, २; १५४, १; १६७, १; १७०, १.
मधुऽअदः १. १६४, २२.
मधुऽअर्णसः १. ६२, ६.
मधुऽजिह्वः १. ४४, ६.
मधुऽजिह्व १. १३, ३; ६०, ३.
मधुऽजिह्वाः ९. ७३, ४; ८५, १०.
मधुदुघे इति मधुऽदुघे ६. ७०, १; ५.
मधुऽदोघं ७. १०१, १.
मधुधा ३. ६१, ५.
मधुऽधारं २. २४, ४.
मधुनः ३. १, ८; ४. ३५, ४; ४४, ४; ४५, १; ६. २०, ३; ८. ५, १९; २४, २०; १००, २; ९. ८३, ४; १०. ११३, २.
मधुना १. २३, १६; ३४, ३; १०९, ४; १५४, ४; १५७, २; २. ३७, ५; ३. ८, १; ४. २६, ५; ४५, ३; ५७, ८; ९. ११, २; ८६, ४३; १०. ५४, ६; ६८, ४; ११०, १०; १२०, ३.
मधुने ४. ४५, ३.
मधुऽपं ५. ३२, ८.
मधुऽपाणिं १०. ४१, ३.
मधुऽपातमा ८. २२, १७.
मधुऽपृचं २. १०, ६.
मधुऽपृष्ठं ९. ८९, ४.
मधुऽपेभिः १. ३४, १०; ४. ४५, ३.
मधुऽपेयः ६. ४४, २१.
मधुऽपेयं १. ३४, ११; १०. ४१, ३.
मधुऽपेयाय ४. १४, ४.
मधुऽपौ १. १८०, २.
मधुऽप्रतीकः १०. ११८, ४.
मधुऽप्सरसः ४. ३३, ३.
मधुऽमत् १. २८, ८; ७८, ५; ९०, ७; ११९, ९; २. १३, ६; ३. ७, २; ३२, ४; ४. ३, ९; ५७, ३; ५८, १०; ५. ६३, १; ६९, २; ८. ८, ११; ९. ८६, १८; ३७; १०. २४, ६[2]; ६३, ३; ६४, ९.
मधुऽमतः १०. २४, ६.
मधुऽमती १. २२, ३; ३. ५७, ५.
मधुऽमतीः ४. ५७, ३; ९. ९७, ३१; १०. ३०, ४.
मधुमत्ऽतमः १. ४७, १; ९. ६३, १६; ६४, २२; ६७, १६; १००, ६; १०५, ३; १०६, ६; १०८, १; १५.
मधुमत्ऽतमं १. ४७, ३; ५. ११, ५; ७. ४७, २; १०२, ३; ८. ९, ७; ९. ३०, ५; ६; ५१, २; ६२, २१; ६३, १९; ८०, ४; १०. १४, १५.
मधुमत्ऽतमस्य ६. ६८, ११.
मधुमत्ऽतमाः ८. ३, १५; ९. १२, १; १०१, ४.
मधुमत्ऽतमानि १०. ११२, ७.
मधुमत्ऽभिः ४. ३, १२.
मधुऽमत्या १. १५७, ४.
मधुऽमंतः १. १३५, १; ४. ४५, २; ४; ५; ५. ६३, ४; ७. ६०, ४; ९०, १; ९६, ५; ९. ६८, १; ८६, १; २; १०. ९८, ४.
मधुऽमंतं १. १३, २; ११२, ९; १४२, २; १८०, ४; ३. ४, २; ३५, ८; ४. ४५, ३; ५; ५७, २; ५८, ११; ६. ४४, १४; ७. ४७, १; ६९, ३; ८. ५१, १०; ५७, ४; ८७, २; ९. ८०, ५; ८५, १०; ९७, १४; १०. २४, १; ३०, ३; ७; ८; ९६, १३.
मधुऽमान् १. ९०, ८[2]; २. ४१, १४; ४. ५७, ३; ५८, १; ६. ४७, १; ८. ९, ४; १७, ६; ९. ६१, ९; ६३, ३; ६८, ८; ६९, २; ७७, १; ८५, ६; ८७, ४; ९६, १३; ९७, ४८; १०६, ७; ११०, ११; १०. ९८, ३.
मधुऽयुवा ५. ७३, ८; ७४, ९.
मधुला १. १९१, १०–१३.
मधुऽवचाः ४. ६, ५; ५. ४३, २; ७. ७, ४.
मधुऽवर्णः ५. ७७, ३.
मधुऽवर्णे १. ८७, २.
मधुऽवर्णो ८. २६, ६.
मधुऽवाहनः १. १५७, ३.
मधुऽवाहनं १०. ४१, २.
मधुऽवाहने १. ३४, २.
मधुऽवृधं १०. ७५, ८.
मधुव्रते इति मधुऽव्रते ६. ७०, ५.
मधुऽश्चुतः ७. ४९, ३; ९. ६२, ७.
मधुऽश्चुतं ४. ५७, २; ९. १२, ६; २३, ४; ३६, २; ५०, ३; ६५, ८; ६६, ११; ६७, ९; १०३, ३; १०७, १२.
मधुऽश्चुता ६. ७०, ५.
मधुऽसुत् ४. ३, ३; १०. ६४, १५.
मधुसुत्ऽतमः ३. ५८, ९.
मधुऽहस्त्यः ५. ५, २.
मधूनां १. ११७, ६; १८३, ४; ३. १, ७; ४३, ३; ४. ४६, १; १०. ५, ४.
मधूनि १. १७७, ३; ३. ५७, ५; ५८, ४; ५. ४३, ३; ७. २४, २; ६७, ४; १०. २९, ६; ३०, १३; ५४, ६.
मधो इति १. १८७, २.
मधो इति १. १८७, ७.
मधोः १. १४, ८; २. ३४, ५; ३. ४०, ६; ५. ४३, ६; ८. ६, ४३; १०३, ६; ९. ५, ३; १७, ८; २३, १; ५१, ३; ७३, २; ७५, ४; १०६, १४; १०. ४९, १०.
मधौ ७. ३२, २; ५९, ६; ८. २१, ५; ९. ११, ५.
मध्यतः ३. २१, ५; ८. २, ९; १०. ४२, ११.
मध्यंदिनं १०. १५१, ५.
मध्यंदिनात् ४. २८, ३.
मध्यंदिने ५. ६९, ३; ७६, ३; ८. १, २९; १३, १३; २७, १९; २१.
मध्ये ३. ३०, १७; ६. ४३, २; ७. ८८, ३; ८. ४०, ३; १०. ५५, ३; १११, ८.
मध्यमैः १. १६४, १; ८. ४१, २.
मध्यमं १. २४, १५; २५, २१; ७. ३२, १६; ८. ६१, १५; ९. १०८, ९.
मध्यमऽस्वाट् २. २९, ४.
मध्यमशीःऽइव १०. ९७, १२.
मध्यमस्याः १. १०८, ९; १०.

म॒ध्य॒मा ६. २५, १; १०. ८१, ५.

म॒ध्य॒माः १०. १५, १.

म॒ध्य॒माभि॑ः ६. ६२, ११.

म॒ध्य॒मास॑ः ४. २५, ८; ६. २१, ५.

म॒ध्य॒मासु॑ ९. ७०, ४.

म॒ध्य॒मे ५. ६० ६.

म॒ध्य॒मेभि॑ः ३. ३२, १३.

म॒ध्य॒मेषु॑ १. २७, ५.

म॒ध्य॒ऽयुव॑ः १. १७३, १०.

म॒ध्या १. ८९, ९; ११५, ४; २. ३८, ४; १०. ६१, ६.

मध्या॑त् ७. ३३, १३; ४९, १.

मध्ये॑ १. ३२, १०; ३३, ११; ६९, २; १०५, १०; ११; १०८, १२; १५८, ३; १६४, ३०; १८२, ७; ३. १४, २; ४. ५८, ५; ५. १, ६; ४४, ३; ४७, ३; ६. १२, १; ७. ४१, ४; ४९, ३; ६८, ७; ८९, ४; ८. २७, २०; ३४, १८; ७०, १०; ९. ६५, २३; १०. ५, १; ११, २; १५, १४; १०२, ५; ९; १३८, ३; १३९, २.

मध्व॑ः १. १४, ४; ७; ३४, १०; ४७, ९; ८४, १०; ८५, ६; ११७, १; १३५, ४; ८; १४१, ३; १५४, ५; १६९, ४; १८०, १; ४; १८१, ६; १८२, २; २. १६, ५; १९, २; ३. ३१, १६; ३६, ७; ४०, १; ४७, १; ४. २०, ४; २७, ५; ३४, ६; ४५, ३; ४; ४७, १; ५०, ३; ५. ३३, ७; ३४, २; ४३, ३; ४; ५४, ८; ६२, ७; ७३, ८; ६. ३९ १; ४१, २; ६९, ७; ७. ३८, ८; ५७, १; ७३, २; ७४, ३; ९१, ५; ६; ९२, २; १०१, ४; ८. १, २५; ५, १४; २४, १६; ४९, ४; ५०, ४; ५३, ३; ५९, ३; ६९, ७; ८२, १; ८५, १; ८७, १; ९. २, ९; ७, २; ८; ९; २४, ७; ६२, ६; ७१, ४; ७७, २; ८६, ४०; ८९, ३; ६; ९७, ४४; १०९, २०; १०. ५, ५; २९, ७; ३०, ८; ८३, ७; ९६, १२; ११२, ६; ११६, १; ४; १२३, ३.

मध्वा॑ १. ४७, ४; १४२, ३; १८८, २; ३. ५४, २१; ५८, ६; ६२, १६; ४. ३८, १०; ४३, ५; ५. १९, ३; ४२, ३; ४३, १; ८. ४, ८; ७२, ९; ९. ५, १०; ९७, ११; १०७, ६; १०. १२, ४; ३४, ७; ११०, २.

मन॑ः १. २५, ३; ३२, ८; ४८, ४; ५४, ३; ९; ५५, ७; ७१, ९; ८४, ३; ९४, १२; १०२, ५; ११९, ९; १३४, १; १३८, १; १५९, २; १६४, १८; १७०, ३; १८७, ६; २. २६, २; ३. ३७, २; ५. ३०, ४; ३५, ४; ३६, ३; ३९, ३; ६१, ७; ८१, १; ६. ९, ५; ६; १६, १७; ५३, ३; ७५, ६; ७. २०, ६; २४, २; २५, १; २७, ५; ८. १, ७; ११, ७; १३, २०; १७, १३; १९, २०; २४, ६; ३१, १५; ३३, १७; ४५, ३२; ३६; ६१, २; ६२, ५; ९२, २८; ९९, ४; १००, ५; ९. ११४, १; १०. १०, ३; १३; १४; ११, २; २५, १; ४३, २; ५७, ३–६; ५८, १; ५९, ५; ६०, ८; १०; ६१, ३; ८५, १०; ११७, २; ११९, १; १४५, ६; १५२, ५; १६४, १; २; १९१, ३; ४.

मन॑ःऽअंगा १०. १०६, ८.

म॒न॒ःऽचित् ९. ११, ८.

मन॑ःऽजवसा १. ११७, १५; ८. २२, १६.

मन॑ःऽजवाः १. १६३, ९; ४. २६, ५; ५. ७७, ३; ६. ६३, ७; ७. ६८, ३; ८. १००, ८.

मन॑ःऽजवेभिः ६. ६२, ३.

म॒न॒ःऽज॒वेषु॑ १०. ७१, ७.

म॒न॒ःऽजुव॑ः १. ८५, ४; १८१, २; १८६, ५.

म॒न॒ःऽजुवे॑ १. ११९, १; १०. ८१, ७.

म॒न॒ःऽजुवा॑ १. २३, ३; ६. २२, ६.

म॒न॒ःऽधृत॑ः ३. ३८, २.

म॒न॒ःऽयुज॑ः १. १४, ६; ५१, १०; ४. ४८, ४; ५. ७५, ६.

म॒न॒ःऽयुज॑ं ८. १३, २६; ९. १००, ३.

म॒न॒ःऽयुजा॑ ८. ५, २.

मन॑ःऽवाताः ३. ३८, २.

म॒न॒ना ३. ६, १.

म॒नना॑ः ९. ७०, ३.

म॒नं॒त॒ १०. ६७, २.

म॒न॒न्या॑ १०. १०६, ८.

मन॑वः १. ८९, ७; ८. १८, २२; १०. ६६, १२; ९१, ९.

म॒नवं॑ते १०. १२, ६.

मन॑वे १. ३१, ४; ३६, १०; ११२, १६; १२८, २; १३०, ५; ८; १४०, ४; १६५, ८; १६६, १३; १८९, ७; २. १९, ४; २०, ७; ३. ३४, ४; ५७, ४; ४. २६, ४; २८, १; ५. २, १२[२]; ३०, ७; ३१, ६; ६. ४९, १३; ७. ९१, १; ८. १०, २; १५, ५; २२, ६; २३, १७; २७, ४; १४; २१; ९. ९६, १२; १०. ११, ३; ४३, ४; ८; ४६, ९; ४९, ९; ७३, ७; ७६, ३.

म॒नवै॑ १०. ५२, १.

मन॑सः १. ७६, १; ११७, २; ११८, १; १५१, ८; १८१, ३; १८३, १; ४. ३६, २; ७. ३३, ११; ९. ११, ८; २८, १; ९७, २२; २८; १०. ३०, १; ३७, १२; ३९, १२; ७१, ८; ८७, १३; ९०, १३; ११२, २; १२८, ४; १२९, ४.

म॒न॒स॒ः १०. १६४, १.

म॒न॒सस्य॑ ५. ४४, १०.

मन॑सा १. २०, २; ३१, १३; ३३, ११; ५४, ५; ६१, २; ६४, १; ७६, १; ७७, २; ९१, २३; ९३, ८; १०२, ३; १०९, १; ११२, १८; १३९, २; १४५, २; १५१, ८; १५७, ६; १५८, २; १६३, ६; १२; १६४, ५; ८; २७; ३६; ३७; १६५, २; १७१, २[२]; १७३, ११; १८२, ५; २. ३, २; ३; १०, ५; २३, १२; ३२, २; ३; ४०, ३; ३. १, १३; ४, ५; ८, ४; १४, ५; १९, ३; २६, १; ३१, १; ५; ९;

३८, ६; ६०, १; २; ४. १, १५; २, ३; १६, १०; २४, ६; २५, ३; २७, ३; ३३, ९; ५८, ६; ५. ४२, ४; ४४, ७; ६. २८, ५; ४०, ३; ४; ४६, १०; ४९, ५; ७. ४, ८; ६४, ४; ६७, १; ७; ६९, २; ९०, ५; ९८, २; १००, १; १०४, ८; ८. २, ३७; २६, २५; ३१, १२; ४८, ७; ८४, ५; १०२, २२; ९. ६८, ५; ७४, ८; ७७, २; ४; १०. २, ५; ५, ३; १७, १२; ३०, ६; १३; ३१, २; ४७, ७; ५०, ७; ५३, १; ११; ६३, ७; ६५, ५; ६७, ८; ७०, ४; ७१, २; ७४, २; ८७, ४; ८२, १; ८५, ९; ८८, १६; ९५, १; ११४, ४; ११६, २; १२१, ६; १३०, ६; १३५, ३; १४७, २; १६०, ३; १७७, १; २; १८१, ३; १८३, १.

मनसि १०. १०, ३.

मनसे १. ७३, १०; १०८, २; ४. ३७, २; ६. २१, ४.

मनस्मयं १०. ८५, १२.

मनस्यवे १०. १७१, ३.

मनस्यसि ८. ४५, ३१.

मनस्ये १०. २७, ५.

मनस्वान् २. १२, १.

मना ८. ७८, २; १०. ६, ३.

मनांसि ५. १, ४; ६. ४४, ८; ७. ५६, ८; ८. २, २१; १०. १०३, १०; १९१, २.

मनानक् १०. ६१, ६.

मनानाः ६. ६७, १०.

मनां १. १७३, २.

मनामहे १. २४, २.

मनामहे १. २४, १; २६, ८; १५९, ५; ५. १३, २; ३५, ८; ४८, १; ५०, ५²; ६६, ३; ७. ६६, १२; ८२, १०; ८. ११, ५; ४७, ३; ५३, ७; ६१, ११; ६८, १३; ९. ४१, २; १०. ६४, १.

मनायतः २. २६, २.

मनायुति १. १३३, ४².

मनायुः ४. २५, २; ५.

मनायै २. ३३, ५; ४. ३३, २.

मनायोः १. ९२, ९; ४. २४, ७.

मनावसू इति ५. ७४, १.

मनिष्ये ६. ९, ६.

मनीषयां १. ९४, १; ५. १७, २; ८. ७२, ३.

मनीषा १. ५४, ८; ६१, २; ७०, १; ७६, १; ९१, १; १०१, ७; १२६, १; १६५, १०; १८६, १; २. २०, १; ३. ८, ५; ३३, ५; ५७, ४; ५. ११, ५; ४७, १; ६. ४९, ४; ६७, २; ७. २४, २; ३४, १; ७०, ७; ९९, ६; १०. ४, ६; २९, ३; ११४, ६; १२४, ९; १२९, ४.

मनीषाः १. ६२, ११; ४. ११, ३; ४१, ८; ९; ६. ३४, १; ६६, ११; ९. ६८, ८; ८६, १७; ९५, ३; ९६, ७; १०. २६, १; २९, ४.

मनीषाणां १०. ४५, ५.

मनीषां १. ११०, ६; ११२, २४; ३. ३८, १; ५७, १; ५८, २; ४. ५, ३; ६, १; ११, २; ५. ८३, १०; ६. ४७, ३; ७. २२, ४; ८५, १; ८. ५९, ६; ९६, ११; ९. ९५, ५; ९७, ३४; १०. २०, १०; २८, ५; ७७, ८; ९४, १४; १११, १; १७७, २.

मनीषिणः २. १९, १; १०. ८१, ४; १११, १.

मनीषिणः १. १६४, ४५; २. २१, ५; ३. १०, १; ५. ५७, २; ८. ५, १६; ४३, १९; ४४, १९; ९. ६८, ६; ७२, २; ६; ७३, ७; ७९, ४; ८५, ३; ९९, ५; १०७, १४; १०. ६४, १५.

मनीषिणः १. १३, ५; १८२, १.

मनीषिणे ९. ७८, ३.

मनीषिणे ८. १४, २.

मनीषिऽभिः १. ३४, १; ५२, ३; ९. ६४, १३; ७६, २; ८६, १९; २०; १०७, ११.

मनीषी ७. २२, ६; ९. ९१, १; ९६, ८; ९७, ५६; १०. ६३, १७.

मनुः १. ३६, १९; ८०, १६; ११४, २; १३९, ९²; २. ३३, १३; ४. २६, १; ५. ४५, ६; ८. ६३, १; १०. ५१, ५; ५३, ६; ६२, ८; ११; ६३, ७; ६९, ३; १००, ५.

मनुःऽहितः १. १३, ४; १४, ११; ६. १६, ९; ८. १९, २४; ३४, ८; १०. २६, ५.

मनुःऽहितं १. १०६, ५; ३. २, १५; ६. ७०, २; ८. १९, २१.

मनुऽजातं १. ४५, १.

मनुतां ६. ४७, २९.

मनुना ७. २, ३.

मनुऽप्रीतासः १०. ६३, १.

मनुं १. ११२, १८; ६. २१, ११; ९. ९२, ५.

मनुऽवत् २. १०, ६.

मनुषः १. २६, ४; ३६, ७; ७६, ५; १२८, १; १६७, ३; १७५, ३; १८०, ९; १८१, ८; १८९, ७; २. २, ५; ६; ८; १८, २; ३. २, १; ३, २; ६; २६, २; ६०, ६; ४. १, ९; २, १; ६, ११; ३७, १; ५. ५, ७; २९, १; ७; ६. ४, १; १०, २; १४, २; १५, ४; ७. ८, २; ९, ४; ७०, २; ७३, २; ८. २३, १३; ४९, ८; ५०, ८; ८७, २; ९. ७२, ४; १०. ११, ५; २१, ७; २५, ८; ४९, ७; ८०, ६; १०४, ४; ११०, १; ७.

मनुषः १०. ६३, ६.

मनुषस्य १. ३१, ११.

मनुषा २. १०, १.

मनुषाऽइव १. १३०, ९.

मनुषाय १. ११७, २१; १०. ६५, ४.

मनुषे १. ५२, ८; २. २०, ६; ५. २९, ३; ७. ९१, ३; १००, ४; ९. ७४, ५; १०. ९९, ७; १०४, ८.

मनुष्यः १. ५९, ४; २. १८, १; १०. ९८, ८.

मनुष्यऽजाः १०. ८५, ४०.

मनुष्यां १. ९२, ११; १२४, २; २. २३, ९.
मनुष्यांः १. १६४, ४५; ४. १, १३; ७. ८९, ५; १०. ३५, ८; ८५, ३७; १०९, ६; १३०, ५; ६; १५०, ४.
मनुष्यांन् ६. ४७, १६.
मनुष्यांसः १०. ७०, ३.
मनुष्यांसु १. १४८, १.
मनुष्यैभिः ३. ४, ८; २९, २.
मनुष्येऽइति ३. १, १०.
मनुष्वत् १. ३१, १७; ४४, ११; ४६, १३; १०५, १३; १४; २. ५, २; ३. १७, २; ३२, ५; ४. ३४, ३; ३७, ३; ५. २१, १[३]; ६. ६८, १; ७. २, ३; ११, ३; ८. २७, ७; ४३, १३; ४३, २७; १०. ६१, १५; ७०, ८; ११०, ८.
मनूनां १. ९६, २.
मनै १०. ९७, १.
मनोः १. ६८, ४; ३. ६०, ३; ७. ३५, १५; ८. ३०, २; ४७, ४; ९८, ६; १०. ३६, १०.
मनोतरां १. ४६, २; ८. ८, १२.
मनोतां २. ९, ४; ६. १, १; ९. ९१, १.
मनौ ८. ५१, १; ५२, १.
मनौ ८. ७२, २; ९. ६३, ८; ६५, १६.
मंतवः १. १५२, १; ९. ७३, ६; १०. ६३, ८.
मंतवे १. ११२, २.
मंतवै ७. ४, ८.
मंतुः १०. २२, ४.
मंतुऽमः १. ४२, ५; ६. ५६, ४; १०. १३४, ६.
मंत्रैः १. १४७, ४; १५२, २; १०. ५०, ४, ६; १९१, ३.
मंत्रऽकृतां ९. ११४, २.
मंत्रं १. ३१, १३; ४०, ५; ६; ७४, १; २. ३५, २; ७. ७, ६; ३२, १३; १०. १०६, ११; १९१, ३.
मंत्रयंते १. १६४, १०.
मंत्रये १०. १९१, ३.
मंत्रऽश्रुत्यं १०. १३४, ७.
मंत्राः ६. ५०, १४; १०. १४, ४; ९५, १.
मंत्रान् १. ६७, २.
मंत्रेभिः १. ६७, ३.
मंत्रैः ३. ५३, ८; १०. ८८, १४.
मंथः १०. ८६, १५.
मंथत ३. २९, ५.
मंथति ३. २९, ६.
मंथंति ६. १५, १७.
मंथां १. २८, ४.
मंथाम ३. २९, १.
मंथिनं ३. ३२, २.
मंथिनां ९. ४६, ४.
मंद ६. १८, ९.
मंदतु ६. १७, ३; ७. २२, १.
मंदत्ऽवीराय ८. ६९, १.
मंदध्यै ४. १६, २.
मंदध्वे ८. ७, १४.
मंदन् १०. ८९, १६.
मंदनाः ९. १०७, २६.
मंदंतु १. १३४, २; २. ११, ११; ८. १, १५; ४, ४; ४५, १४.
मंदंतु १. १३९, ६; ८. ४५, २४; ६४, १.
मंदमानः ९. ६५, ५; १०. ७३, ५; ११२, २.
मंदमानाः ६. ६७, ५.
मंदमानाय १०. ५०, १.
मंदय ३. ३०, २०.
मंदयत्ऽसखं १. ४, ७.
मंदयध्यै ४. २९, ३.
मंदयन् ९. ६७, १६.
मंदयुः १. १७३, २.
मंदसानः १. १०, ११; १००, १४; १३१, ४; २. ११, ३; १५; १७; ३०, ५; ४. १७, ३; २६, ३; २९, १; ३२, १०; ५. ६०, ८; ६. १७, ५; २६, ६; ८. ४९, ४; ९३, २१; १०. २८, ७.
मंदसानं ५. २९, २.
मंदसाना ४. ५०, १०; ८. ८७, २.
मंदसानाः २. ११, १४; ४. ३४, १०; ३५, ६; ५. ६०, ७; ७. ३६, ७.
मंदसे १. ५१, १२; ८. १२, १६; १७; ५४, २.
मंदसे ८. ९३, १९; १०. ५०, २.
मंदस्व १. २६, ५; २. ३७, १; ८. ६, ३९; ६०, ४; १०. १४०, ३.
मंदस्व २. ३६, ३; ३. ४१, ६; ६. २३, ८; ८. ८२, ३.
मंदानः १. ८०, ६; ८२, ५; २. १९, २; ३. ५०, ३; ५. ३२, ६; ६. ४३, ४; ४४, १७; ८. १३, ४; १५, ५; २६, २५; ३२, ५; ३३, ७; ४५, ३१; ९. ४७, १.
मंदानं ८. ८८, १; १०. १६७, २.
मंदाना ७. ९४, ११.
मंदामहे १. १२२, १३.
मंदिनः १. १३४, २; २. ११, ११; २०; ४. ४५, ४; ९. १०१, ४; १०. २८, ३; ४३, ४.
मंदिनं १. १२१, ८; १२; १०. ९६, ६.
मंदिनां १. ५४, ४; १०. ९४, ४.
मंदिनें १. ९, २; १०१, १.
मंदिऽभिः १. ९, ३.
मंदिं १. ९, २.
मंदिष्ट १. ५१, ११.
मंदिष्ठः ८. २, ९.
मंदी ८. २, ३३; ९. ५८, १; १०७, ९.
मंदू इति १. ६, ७; १०. ६१, १५.
मंदे ५. ४, १.
मंद्रं १. १४४, ७; ८. ७४, ७.
मद्रऽअंजनी ९. ६९, २.
मंद्रः १. २६, ७; ३६, ५; १४१, १२; २. २८, १; ३. १, १७; १०, ७; १४, १; ४. ६, २; ५; ९, ३; ५. ११, ३; ६. १, ६; ७. ७, २; ४; ८, २; ९, १; २; ४२, ३; ८. ६०, ३; १०३, ६; ९. ६७, १; १०९, ८; १०. ६, ४; १२, २; ६१, २०; ७३, १.
मंद्रऽजिंव्हः ६. ७१, ४.
मंद्रऽजिंव्हं १. १९०, १; ४. ११, ५; ५०, १; ५. २५, २.
मंद्रऽजिंव्हा १. १४२, ८.

मंद्रऽतमः ५. २२, १; ६. ११, २; ८. ७१, ११.
मंद्रऽतमं ६. ४, ७.
मंद्रऽतमाः ९. ९७, २६.
मंद्रऽतरः ३. ७, ९.
मंद्रं ३. २, १५; ४. २, ७; २६, ६; ५. १७, २; ६. १०, १; ४८, १४; ७. १०, ५; ८. ४३, ३१; ४४, ६; ९. ६५, २९; १०. ४६, ८.
मंद्रया १. ७६, ५; ५. २६, १; ७. १६, ९; ९. ६, १; १०७, ८.
मंद्रऽयुवः ९. ८६, १७.
मंद्रस्य ३. २, ४; ६, ७; ६. ३९, १; ९. ६८, ६.
मंद्रा १. १००, १६; ८. १००, १०; ११; १०. १०१, २.
मंद्राः १. १६६, ११; ७. १८, ३; १०. ९३, ४.
मंद्राः १. १२२, ११.
मंद्राभिः ६. १६, २.
मंद्रां ८. ९५, ५.
मंद्रेभिः ८. ४३, ३१.
मंद्रैः ३. ४५, १.
मंधाता १०. २, २.
मंधातारं १. ११२, १३.
मंधातुः ८. ३९, ८.
मंधातृऽवत् ८. ४०, १२.
मन्मं १. ७७, ४; १२०, ३; १२९, ६[२]; १३१, ६; १४८, २; १५४, ३; १६२, ७; २. ४, ८; १९, ८; ४१, १८; ४. ३, ३; ५, ६; ६, १; ११, २; १६, २; ५. १२, १; ४१, ३; ६. ५, ६; ३८, ४; ४९, ३; ५२, १४; ५६, ४; ६२, ४; ६८, ९; ७. १०, २; १३, १; ५७, २; ८७, ३; ८. ५२, ९; ९. ९४, १; १०. ४, १; ३६, ५; ५४, ६; ६६, २; ९६, ११; १८२, १.
मन्मन् ६. ६३, १; १०. १३८, १.
मन्मनः १. १४०, ११; ७. ९४, १; १०. ३५, ९.
मन्मना १. १४०, १; १५१, ८; ३. १४, ५; ८. ६, ११; ४४, २; १२; ७६, ६; ९. ४२, २.
मन्मनां १. १५१, ६.
मन्मनि १०. १२, ८.
मन्मऽभिः १. २६, २; १२७. २[२]; ३. ११, ८; ४. ३, १५; ८. ७, १५; १९; ४१, २; ४४, २६; ६०, ३; ७४, १; १०. ५७, ३; ७८, १; ८७, २४.
मन्मऽशः ८. १५, १२.
मन्मऽसाधनः १. ९६, ६; १५१, ७.
मन्महे १. ६२, १; ५. ५२, ३; १०. ९२, ३.
मन्मानि १. १६५, १३; ७. ६१, २; ६; ८. ३९, ३; १०. ११०, २.
मन्यत ४. १७, १; ४.
मन्यंते ६. ५२, २.
मन्यते ८. ४, १२; १०. ८५, ३; ८६, ९; ९१, २; १४६, ४.
मन्यथाः १. १२६, ७.
मन्यमानः २. २३, १२; ४. २०, ५; २९, २; ५. ४, १०; ३२, ३; ६. २५, ५; ७. ४१, २; १०. ३४, १३.
मन्यमानं २. ११, २; ६. १९, १२; १०. ८, ९.
मन्यमानस्य ३. ३२, ४; ७. २२, ८.
मन्यमाना ४. १८, ५.
मन्यमानाः १. १९०, ५; ३. ५३, २३; ६२, १; ८. ७, ३४.
मन्यमानान् १. १७८, ५; ७. ९८, ४.
मन्यमानैः १. ३३, ९.
मन्यवः ४. ३१, ६.
मन्यवे १. २५, २; ३७, ७; ८०, ११; १४; ६. १६, ४३; ८. ६, ४; ८२, ३; ८४, ४; ९९, ६; १०. ३४, ८; ११३, ६; १४७, १.
मन्यसे १. १२९, ५; ५. १७, २; २०, १; ३९, २; ५६, २; ८. ९३, ५; १०. २१, ४.
मन्युसे १. १७०, ३.
मन्याते १०. २७, ११.
मन्युः २. २४, १४; ७. ८६, ६; ८. ६, १३; ४८, ८; ७१, २; १०. ३४, १४; ८३, २[३]; ८४, ७; ८९, ६.
मन्युना १. १०१, २; १३९, २[२]; २. २४, २; ६. ४६, ४.
मन्युऽभिः ७. ५६, २२.
मन्युं १. २४, ६; १०४, २; २. २३, १२; ४. १७, १०; ५. ७, १०; ६. २५, २; ७. १८, १६; ३६, ४; ६०, ११; ६१, १; ८. ४, ५; १९, १५; ७८, ६; ९. ९७, ८; १०. ३५, ४; ८३, २; १२८, ६; १५२, ३.
मन्युऽमत् ७. १०४, ३.
मन्युमत्ऽतमः ४. ३०, ७.
मन्युऽमीः १. १००, ६; २. २३, ४.
मन्युऽम्यः ७. १८, १६.
मन्युऽसाविनं ८. ३२, २१.
मन्ये ५. ९, १; ६. १८, ४; ७. २, ७; ८. ४८, ६; ९६, ४[४].
मन्ये १. १०४, ७; १२७, १; १५९, २; ४. २, ३; ५. ६, १; ६. ३०, २; ५२, १; १०. ७, ३; ७३, १०; ९९, ५; १०७, ५; १३०, ६; १७९, ३[२].
मन्येथां ३. ५८, ४; ८. २६, ५.
मन्यो इति १०. ८३, १–६; ८४, १–६.
मन्योः ४. १७, २; ६. १७, ९; १०. ७३, १०; ८७, १३; १५२, ५.
मन्वत ४. १, १६; ८. २९, १०.
मन्वते १०. २, ५.
मन्वानः ५. ५२, १५.
मन्वानाः १०. १३८, १.
मर्म १. १०, ९; २३, ८; २१; ५०, ११; ११०, २; १४२, ४; १४८, २; १८२, ४; २. १८, ७; ४१, ४; १५; ३. २४, ३; ४२, ३; ६२, ८; ४. १८, ७; २४, १०; २६, २; ४२, १; ५. ७५, १; ६. ५०, १५; ५२, १४; ५५, ५; ७५, १९; ७. ३१, ५; ८. १, १५; १८; २९[३]; ३, ३; ५, ३०; ६, १२; १८; ८, ६; ९, ८; १७, १; १९, २९; ३३, १६; ३८, ६; ४३, १७; ४४, ५; २२; ६०, ६; ७८, ९; ९१, ६; ९. ६९, ८; १०. २५, २; २७, ५; २८, १; ३३, ८; ४२, ३; ४७, ७; ४८, ३; ५३, ४; ५; ६६, ११; १२४, ५; १२५, ७;

१२८, १; २[२]; ४; १४५, ३; १५९, २; ३.
ममंकस्य १. ३१, ११.
ममंकाय १. ३४, ६.
ममंत् ४. १८, ८[३]; ९.
मुमर्ताऽइव ६. १०, २.
मुमर्तुः ३. ३२, ७.
मुमुत्तनं १०. १७९, १.
मुमर्त्तु १. १२२, ३[२]; १०. ११६, ३[२].
मुमुत्तु १. १२१, ६; ३. ५१, ११; ७. २२, २; ८. ९५, ७; ९. ९६, २१; १०. ५९, २.
मुमुत्सि ४. २१, ९.
मुमर्दः ७. २४, १.
मुमुदुः ४. २०, ४.
मुमर्दन् ४. ४२, ६.
मुमुद्धि १०. ९६, १३.
मुमुद्धि ८. ९५, ८.
मुमंदु २. ३३, ६.
मुमंदुत् ८. ६१, ९.
मुमंदुर्षी ५. ६१, ९.
मुमंधि १०. २७, २०.
मुमुन्यात् १०. ३१, २.
मुमुऽसुत्येषु १०. ४२, ४.
मुमर्हः २. १७, ७.
मुमुहुत ७. ५२, २.
मुमुहुतां १. ९४, १६; ९५, ११; ९६, ९; ९८, ३; १००, १९; १०१, ११; १०२, ११; १०३, ८; १०५, १९; १०६, ७; १०७, ३; १०८, १३; १०९, ८; ११०, ९; १११, ५; ११२, २५; ११३, २०; ११४, ११; ११५, ६.
मुमुहुस्व ३. ५२, ६; १०. १२२, ३.
मुमुहानं १. ११७, १७.
मुमुहे ८. १, ३२; १२, ६.
मुमुहे १. १६५, १३; ५. २७, १; ८. २, ४२; १०. ६२, १०.
मुमाते इति ३. ३२, ७.
मुमार्द ६. ४७, २.
मुमादु २. २२, १; ७. २६, १; २.
मुमार १०. ५५, ५.
मुमिरे ३. ३८, ३.
मुमिरे १. १५९, ४; १६३, ८; ३. ३८, ७[२]; ५. ५५, २; ७. २१, ७; ९. ८३, ३; १०. ७८, ७.
मुमुः १. ११०, ५.
मुमृजीत ७. ९५, ३.
मुमृजुः १०. ६५, ७; ६६, ९.
मुमृजे ९. १४, ५.
मुमृजे ७. २६, ३; ९. २, ५: १०७, ११.
मुमृड्युः ४. १८, ८.
मुमृऽवांसं १०. ३९, ९.
मुमृऽवान् १. ११६, ३.
मुमे १. १६०, ४; ५. ८५, ५; ८. २५, १८; ९. ६८, ३.
मुमे १. ५७, ५; ५८, १; ८. ४१, १०; ७६, १२.
मुम्नाते इति ७. ३१, ७.
मुम्रुः १०. १०७, ८.
मुम्रुर्षाः १. १४०, ८.
मर्यः १. ३१, ७; ८९, ३; ९३, १; ११४, २; १७६, ४; १८६, ५; ३. १, ३; ५. ४६, ४; ७. ३२, ८; ८१, ३; ८. १८, ७; २०, २४; ३९, ४; ६०, ६; १०. ३७, ८; ४०, १०; ६४, १; ९५, १.
मर्यःऽइव १. १७५, ६; १७६, ६.
मुयुःऽभु १. ८३, ४; २. २७, ५; ३३, १३; ५. ४२, २; १०. १८६, १.
मुयुःऽभुः १. १८७, ३; ४. ११, ४; ५. ४२, १; ६. ५२, ६.
मुयुःऽभुर्ना ३. १६, ६.
मुयुःऽभुर्वः १. १३, ९; ८९, ४; ९१, ९; १२५, ४; १६६, ३; ५. ४३, १; ५८, २; ७. ४०, ६; १०१, ५; १०. ९, १.
मुयुःऽभुवः ८. २०, २४.
मुयुःऽभुर्वं १. १३८, १; २; ९. ६५, २८; ७८, ४; १०. ३९, १०.
मुयुःऽभुर्वा १. ९२, १८; ५. ४२, १८; ४३, ८; ७३, ९; ८. ८, ९; १९; ८६, १; १०. ३९, ५.
मुयुःऽभूः १. १७७, १९; १६४, ४९; १०. १०९, १; १६९, १.
मुयुःऽभून् १. ८४, १६.
मुयंते १०. ४०, १०.
मर्या ८. १००, १; १०. ८५, ३६; १२५, ४.
मर्ये १. २३, २२; ८. ५०, १०; ९. ६६, २१; १०. ४८, ३; १२८, ३[२].
मुयूखाः १०. १३०, २.
मुयूखैः ७. ९९, ३.
मुयूररोमऽभिः ३. ४५, १.
मुयूरंऽशेप्या ८. १, २५.
मुयूर्षैः १. १९१, १४.
मरंते १०. ८६, ११.
मुरंति १. १९१, १२.
मुराति १. १९१, १०; ११.
मुराम १. १९१, १०–१२.
मुरामहे १. ९१, ६.
मुरायी १०. ६०, ४.
मुरायुं १०. १०६, ६; ७.
मरीचीः १०. ५८, ६.
मरीचीनां १०. १७७, १.
मरुतः १. १५, २; ३७, १२; ३८, ३; ११; ८६, १; २; ७; १७२, १; २; ५. ५७, ८; ६. ४९, ११; ६६, ८; ७. ५९, १; ९; १०; ८. ७, १; ११; २०, २३; २७, ५; ८; ८३, ७; ८९, १; ३; १०. ६४, १२.
मुरुतः १. २३, १०; १२; ३१, १; ३७, १३; ४०, १; ४४, १४; ५२, ९; १५; ६४, ६; ११; ८५, १; १०; ८९, ७; ९०, ४; १०७, २; १११, ४; १२२, १, १३४, ४; १६१, १४; १६२, १; १६५, १; २; १६६, ३; ११; १६७, २; ४; १६८, ४; ८; १६९, ३; ५; १७०, २; १७१, ३; १७३, १२; १८६, ८; २. ३४, १; ८; ११; ३. १४, ४; २६, ४; ५; ३२, ३; ४; ३५, ९; ४७, ३; ५४, १३; २०; ४. २, ४; ५. ३, ३; २६, ९; २९, १; २; ६; ३०, ६; ३१, १०; ४१, १६[२]; ४३, १०; ४५, ४; ४६, ३; ५२, ६; ५३, १२; ५४, ३; ८; ५५, १; ५७, ४; ५८, ३; ५; ५९, ८; ६०, २; ६३, ५; ६; ६. १७, ११; २१, ९; ४८, २१; ५०, ४; ६६, २; १०;

७. ९, ५; ३२, १०; ३४, २४; ३५, ९; ३६, ७; ३९, ५; ५१, ३; ५६, १६; १७; १९; ५७, २; ३; ५; ६; ५८, ३; ५; ६; ९३, ८; ८. ३, २१; ७, ४; २०, १४; १८; २०; २५, १०; १४; २७, १; ४६, ४; ५४, ३; ९४, ३; ४; ९; ११; ९६, ८; ९. ५१, ३; ६४, २४; ८१, ४; ९६, १७; १०८, १४; १०. ३५, १३; ३६, १; ३७, ६; ५२, २; ६३, ९; ६५, १; ६६, ४; ७०, ११; ७३, १; ७६, १; ९२, ६; ११; ९३, ४; १०३, ८; ११३, ३; १२२, ५; १२८, २.

मरुतः १. ३९, १; ५; ८–१०; ४०, २; ६४, ९; १३–१५; ८५, ४–६; १२; ८६, ६; ८७, २; ८८, १; ३; ५; ६; १३९, ८; १६५, ६–८; १०–१५; १६६, १; ६; ८; ९; १२–१५; १६७, ६; ८; ९; ११; १६८, ५–७; १०; १७१, १–४; २. ३३, १३; ३४, २; ३; ५–७; ९; १०; १५; ३. १६, २; ५१, ९; ६२, ३; ४. २६, ४; ५. २९, ३; ३६, ६; ४१, ५; ४२, १०; ४३, १०; ५३, ५; ८; १४; १५; ५४, २; ४–७; १०–१२; १३[२]; १४; १५; ५५, ४–१०; ५६, ३; ७; ५७, २; ६; ७; ५८, ३; ४; ६; ५९, ४; ६०, ३; ६; ७; ८३, ६; ८७, २; ८; ६. ४८, २०; ५०, ५; ५२, २; ६६, ७; ७. १८, २५; ३६, ९; ४०, ३; ५६, १०; १२–१५; १८; २१–२४; ५७, ४; ७; ५८, २; ४; ५९, ३; ५; ६; ८; ११; १०४, १८; ८. ७, ९; १३; ३०; १८, २१; २०, २; ६; १०; १५; २१; २२; २५; २६; २७, ६; ९४, १०; १०. ६३, १४; १५; ६४, १३; ७७, ६; ७८, ८.

मरुतां १. २३, ११; ३८, १०; ९४, १२; ११४, ६; १२८, ५; १६७, ७; १६८, ९; १६९, १; २; ७; २. ३, ३; ३. २६, ६; ४. ३, ८; ३९, ४; ५५, ५; ५. ५२, ३; ५३, १; ५६, १; ५; ६०, १; ६. ३, ८; ११, १; ४७, २८; ४८, १२; ७. ३४, २५; ५६, २५; ८. १८, २०; २०, ३; ४६, १७; ९४, १; ९६, ९; १०. ३६, ४; ६४, ११; १०३, ९; १३७, ५.

मरुतां १. ११४, ९; २. ३३, १.

मरुतांऽइव १. १४३, ५; ३. २९, १५; ९. ७०, ६.

मरुत्ऽगण ८. ८९, २.

मरुत्ऽगणः ६. ५२, ११; ९. ६६, २६.

मरुत्ऽगणाः १. २३, ८; २. ४१, १५.

मरुत्ऽगणे १०. ६६, २.

मरुत्ऽतमा १. १८२, २.

मरुत्ऽभिः १. १९, १–९; १०१, ९; १०७, २; १३६, ७; १६९, ८; १७०, ५; १७१, ५; ६; ३. ४७, २; ४; ५१, ८; ५२, ७; ६२, २; ४. ३४, ७; ११; ५. ५२, १; ६०, ८; ६. ४०, ५; ७. ५६, ५; ७; २३[२]; ८२, ५; ८. ७, ३२; ३५, ३; ९६, ७; १०. १२६, ५; १५७, ३.

मरुत्ऽभ्यः १. ६४, १; ८५, ८; ५. ५, ११; ३०, ८; ५२, ५; ५४, ९; ६०, ५; ८. ४१, १; ९. २५, १; ३३, ३; ३४, २; ६१, १२; ६५, २०; १०. ७७, ७.

मरुत्वः १. १०१, ८; ३. ५१, ७; १०. ८४, १.

मरुत्वतः ५. ४२, ६; ८. ६३, १०.

मरुत्वता १. २०, ५; ८. ७६, ४.

मरुत्वती २. ३०, ८; ७. ३१, ८.

मरुत्वतीः १. ८०, ४; ८. १३, २८.

मरुत्वते १. १४२, १२; ३. ३५, ७; ५. ८७, १; ८. ७६, ८; ९. ६४, २२; ६५, १०; १०७, १७; १०. १३, ५.

मरुत्वतः ९. १०७, २५.

मरुत्वंतं १. २३, ७; १०१, १–७; ३. ४७, ५; ८. ७६, १; ५; ६.

मरुत्वंता ८. ३५, १३.

मरुत्वान् १. ८०, ११; १००, १–१५; ११४, ११; २. ३३, ६; ३. ४, ६; ४७, १; ५०, १; ४. २१, ३; ६. ४७, ५; ८. ३६, १; ७६, ७; १०. ९८, १.

मरुत्ऽवृधः ३. १३, ६.

मरुत्ऽवृधे १०. ७५, ५.

मरुत्ऽसखा ७. ९६, २; ८. ७६, २; ३; ९; १०३, १४; १०. ८६, ९.

मरुत्ऽसु १. १४२, ९; ४. १, ३; ५. ५२, ४; ५६, ८; ९; ७. ४२, ५; ८. १२, १६; २७, ३.

मरुत्ऽस्तोत्रस्य १. १०१, ११.

मरै ८. ९३, ५.

मर्कः १०. २७, २०.

मर्चयंति १. १४७, ४; ५; ५. ३, ७.

मर्चयात् २. २३, ७.

मर्जयध्वं ७. २, ४.

मर्जयन् १०. १२२, ५.

मर्जयंत १. ६१, २; ५. ३, ३; ७. ३, ५; ३९, ३; ८. ८४, ८; ९. ६८, ६; ९३, १.

मर्जयंतः १. ६०, ५; ९. ८७, १.

मर्जयंति ९. ८९, ४.

मर्जयंतीः ९. १४, ७.

मर्जयंते १०. ७६, ७.

मर्जयसि ९. १११, २.

मर्जयामसि ९. ९९, ३.

मर्जयेम ४. ४, ८.

मर्ज्यैः ९. ३४, ४; १०७, १३.

मर्ज्यै ९. १५, ७; ४६, ६; ६३, २०.

मर्डिता १. ८४, १९; ४. १७, १७; ८. ६६, १३; १०. ६४, २.

मर्डितारं ४. १८, १३; ८. ८०, १; १०. ३४, ३; ११७, १; २.

मर्त ५. ६६, १.

मर्तः १. ३०, २०; ६४, १३; ७२, ४; १४७, ५; १४९, ५; १६३, ७; २. २३, ७; ३. ५९, २; ४. ४१, २; ५. ५०, १; ६. १, ९; २, ४; १३, ४; १६, २६; ३१; ३२; ४६; ५९, ५; ७०, ३; ७. १, २३; १००, १; ८. १९, ५; ९; २०,

२२; २३, २१; ४४, १५; १०३, ४; ९. १०१, १३; १०. ११, ७; ३१, २; ६३, १३; ९५, ९; १०५, ३.

मर्तऽभोजनं १. ८१, ६; ११४, ६; ७. ३८, २; ४५, ३; ८१, ५.

मर्तऽभोजना ७. १६, ४.

मर्ते १. ३१, ७; ८४, ८; १३६, ५; १४१, ६; १४७, ५; ५. ४१, १३; ६१, १५; ६. ३, १; २; १४, ५; ८. ७१, ४.

मर्तस्य १. ९२, १०; ३. १५, ६; ४. १, ९; २, १०; ९, ६; २३, ५; ५. ८, ४; ६. २८, ४; ७. ८२, ७; ८. ११, ४; ९. ५८, २; ७९, २; १०. १३४, २.

मर्ताः १. ५, १०; ६०, २; १००, १५; १९०, १; २. २७, १०; ३. ९, ६; ४. ११, ५; १७, १९; ५. १४, २; ३१, १३; ६. २१, ३; ६७, ९; ७. १, ९; २८, १; ३७, ७; ८. ११, ५; १०. ४, ५.

मर्ताः १०. ११८, ६.

मर्तात् ४. १०, ७; ५५, १.

मर्तान् १. ७०, ३; ७३, ८; ३. १, १७; ४. २, ३; ११; ५. ३, ५; ६; ७. १८, १८; २३, ५; १०. १२, १; ८७, २१.

मर्तानां १. ६३, ५; ४. २, १८; ८. ३९, ६.

मर्ताय १. ४५, ८; ७७, २; ८४, ७; ५. ८६, ५; ६. ६७, ४; ८. १, २२; २२, १४; ६०, ८; ७१, ६; ७; ९. ९४, ३; ९८, ४.

मर्तासः १. ३८, ४; ११०, ४; १४४, ५; २. १, १४; ३. ९, १; १०, १; १४, ७; ४. ७, २; ५. ९, १; १६, १; २२, ३; ६. १५, ८; १६, ७; ७. ४, ३; २५, २; ८. ११, ६; ६०, १५; ८१, ३; १०. १३६, ३; १५०, २.

मर्तासुः १. १०५, १६.

मर्ते १. १२०, २.

मर्तेषु १. ६७, १; ४. १, १७; ५. १८, १; २५, ४; ६. ५१, २; ६६, १; ७. ४, ४; ६०, २; ७५, २.

मर्तैः ५. ३, ८; १०. ११५, ७.

मर्त्यऽइषितः १. ३९, ८.

मर्त्यः १. १९, २; ३६, ४; १६; ४०, २; ४१, ६; ८३, १; ८६, ७; ९१, १४; १३८, २; १५०, ३; १५५, ५; १७९, ५; २. ३४, ९; ४१, ८; ३. ११, ७; ४. १५, ५; ५. ४, १०; ७, ६; १७, १; २१, ४; ४१, १७^{2}; ५३, १५; ६. २, ५; १४, १; ३०, ४; ६०, ११; ७. ३२, ११; १४; २१; ८. ३, १३; ६, ४४; ७, १५; १४, ४; १८, १; १३; १९, १४; २५; २८; २३, १५; १९; २८, ४; ४६, ४; ६८, ८; १९; ७०, ७; ७४, १५; ९६, २; १०१, १; १६; १०२, २२; १०. २२, ५; ७९, ४; ९१, ११; ९३, २.

मर्त्यऽकृतं ८. १९, ६.

मर्त्यऽत्रा १. १२३, ३; १६९, २; ६. ४४, १०; ६२, ८; ७. ५२, १.

मर्त्यऽत्वना ८. ९२, १३.

मर्त्यं १. १८, ४; ५; २७, ७; ३५, २; ४१, २; ८४, १९; १२९, ३^{2}; १३१, ४; ७^{2}; १६४, २९; १६९, ७; ४. ३७, ६; ५. ३५, ५; ५२, ४; ६७, ३; ८६, १; ७. ४०, ३; ८२, ७; ९४, १२; ८. ४, १६; १८, १४; १५; १९, ३४; २७, १५; १०. २२, ६; १२६, १; २; १७१, ३.

मर्त्यस्य १. १८, ३; ३९, २; ११८, १; २. ७, २; ३. ३९, ८; ४. २२, ९; ६. ४८, २०; ६२, ३; १०; ७. २५, ३; ८. ४८, ३; ७१, १; १०. १०, ३.

मर्त्याः १०. ११८, ५.

मर्त्यात् १. २७, ३.

मर्त्यान् ४. ५८, ३; ८. २, ४; ४८, १२.

मर्त्यानां १. २६, ९; ३१, १६; ३. १, १८; ४. १२, ५; ५. ४, १; ९, ६; ७४, ७; ६. १५, १३; ७. ३९, ६; ८. ७८, ६; १०१, ६; ९. ९७, २४; १०. ४, २; ३३, ८; ८८, १५.

मर्त्याय १. ११३, १८; १२४, १२; १५५, २; २. १९, ५; २७, ९; ३. ३०, ७; ४. ५, २; ११, ३; १२, ३; २४, २; २६, २; ३०, ६; ३४, ४; ३९, ५; ५. ३, १; ४१, ७; ६. १६, २५; ६५, ३; ७. ५, ८; ११, ३; ६५, ३; ७१, २; १०. १५, ७; १८५, ३.

मर्त्यासः १. ११३, ११; ३. २९, १३; ३०, १५; ८. ४८, १; ९७, ९; १०. २, ५.

मर्त्यासु १०. ७९, १.

मर्त्ये ३. २, ९.

मर्त्येन १. १६४, ३०; ३८.

मर्त्येभिः ९. ९१, २.

मर्त्येभ्यः १. ९०, ३; १४५, ५; ८. ९, १६; १०. १७, २.

मर्त्येषु १. ७७, १; ३. ३०, ३; ३९, ४; ५१, ५; ४. १, १; ६; २, १; ५. २, ६; ७, ९; ७४, ८; ६. ४, २; ५, ५; ९, ४; १०, ३; ११, २; १५, ३; ७. ३, १; ६१, १; ९०, २; ८. ११, १; ७१, ११; ८४, २; ९. ११०, ४; १०. ९५, १६; ११८, १.

मर्त्यैः ६. ४८, १९.

मर्धतः ६. ६०, ४.

मर्धति ७. ५९, ४.

मर्धति १. १६६, २; ३. ५४, १४.

मर्धिषत् ७. ३२, ५; ८. ८१, ४.

मर्धिष्टं ७. ७३, ४.

मर्धीः ४. २०, १०; ७. २५, ४.

मर्म १. ६१, ६; ३. ३२, ४; ५. ३२, ५.

मर्मणि ८. १००, ७.

मर्मन् १०. ८७, १५; १७.

मर्मर्तु २. २३, ६.

मर्माणि ६. ७५, १८.

मर्मृजत् १०. २६, ६; ९६, ९.

मर्मृजत ४. १, १४.

मर्मृजतः ४. २, १९.

मर्मृजंत १. १३५, ५.

मर्मृजानः ९. ५७, ३; ६६, २३; ७०, ५; ८६, ११; ९१, २.

मर्मृजानं ९. ९५, ४.

मर्मृजानासः ९. ६४, १७.

मर्मृजेन्यः १. १८९, ७; २. १०, १.

मर्मृज्म ३. १८, ४.

मर्मृज्यते ९. ४७, ४.

मर्मृज्यते १. ९५, ८.

मर्मृज्यंते ४. १५, ६; ८. १०३, ७; ९. २, ७; ३३, ५; ३८, ३.

मर्मृज्यमानः ९. ६२, १३; ८५, ५.

मर्मृज्यमाना: २. ३५, ४.

मर्मृशत् १. १४०, ५; ३. ३८, १; ८. ४१, ७; ९. १४, ८.

मर्यः १. ७७, ३; ११५, २; १६३, ८; १७३, २; ३. ३१, ७; ४. २०, ५; ९. ९३, २; ९६, २०; ९७, १८; १०. ३०, ५.

मर्यःऽइव १. ९१, १३; ९. ८६, १६.

मर्यक ५. २, ५.

मर्यतः १०. २७, १२.

मर्य ८. ४३, २५; १०. ४०, २; ४३, १.

मर्यऽश्रीः २. १०, ५.

मर्याः १. ६४, २; ३. ५४, १३; ५. ५३, ३; ५९, ६; ७. ५६, १; १६; १०. ७७, ३; ७८, १; ४.

मर्याः १. ६, ३; ८. ४५, ३७.

मर्याःऽइव ५. ५९, ३; ५.

मर्यादा ४. ५, १३.

मर्यादाः १०. ५, ६.

मर्यायऽइव ३. ३३, १०.

मर्यासः ५. ६१, ४; १०. ७७, २.

मर्ये १०. ३९, १४.

मर्षिष्ठाः १. ७१, १०.

मर्ला १०. १३६, २.

मशर्शारस्य १. १२२, १५.

मसीय १०. ५३, ४.

मस्तिष्कात् १०. १६३, १.

मर्हः १. १७५, १; २. १६, २; ५. ५२, ३; ७. ४३, ४; ८. ६५, ४; ९. ३१, ३; १०. ४३, ७; १५४, २.

महः १. ३, १२; ६, १०; १९, २; ३; २२, ११; ३१, ३; ३६, ३; ५५, ३; ६१, ७; १००, १; १०२, १; १०५, ६; १०; ११७, ८; १२०, ७; १२१, ८; ११; १२४, ६; १२७, ११; १२८, ७; १३०, ७; १३३, ६; १४६, ३; ५; १४९, १; १५०, ३; १५३, १; १५५, १; १५६, ३; १६८, ६; १६९, १[२]; ६; १७३, १२; १८२, ५; १८७, १; १९०, ८; २. १, ६; २३, २; १७; २४, ७; ३२, १; ३३, ८; ३४, ११; १२; ३७, ६; ३. ७, ६; ९; १६, १; ३१, ३; ३४, ६; ३८, ९; ४६, ३; ४८, २; ५४, ८; ९; ५७, ३; ४. १, ११; २, २०; ४, ११; १२, २; ५; २२, ३; २८, २; ३१, ११; ३४, ५; ३९, २; ४; ४३, ४; ५०, ४; ५३, ४; ५५, ८; ५८, ३; ५. १५, ५; ४१, १; ४३, १; ५२, ७; ६८, ३; ८७, ७; ८; ६. १, २; ६, ६; १६, २; १७, १०; २०, ५; २५, ६; २६, १; २; २९, १[२]; ३२, ४; ४४, ८; ४६, २; ४८, ४; ४९, १५; ५०, ३; ६; १०; ५१, ३; ४; ९; ५५, २; ६६, ३; ७३, ३; ७. १, २४; ३, २; १६, १०; १७, ७; २०, १; २५, १; २८, ५; ३६, ३; ३७, ३; ६६, ६; ८. १६, ३; २३, १६; २६; २९; २५, ५; २४; २६, २३; ३६, ६; ४६, १७; ४७, ८; ५०, ६; ६१, १४; ६८, ३; ७०, २; ८; ९०, २; ९८, ७; १०१, ११; ९. ४६, ५; ४७, १; ४८, १; ६१, २६; ७२, ७; ७३, ३; ८१, ३; ८६, ८; ८८, २; ८९, ७; ९०, ४; ९७, २७; ११०, ८; १०. ८, ५; १०, २; १७, १; २२, ३[२]; १५; २५, १०; ३६, १२; ३७, १; ५५, ६; ५६, २; ६१, २२; २७; ६३, ५; ६४, ६; ९; ७६, २; ७७, ६; ८; ९३, ३; ९९, १२; १०८, २; १२०, ८; १४०, ५; १५०, ४.

महः ७. ६४, २.

महःऽभिः १. ९०, २; १६५, ५; २. १०, ३; ३. ४, ६; ४. १४, १; ५. ५८, ५; ६२, ३; ६. ६४, २; ७. ३, ७; ५८, २; ८८, ४; ८. ७१, १; ९. ९६, २१.

महत् १. ८०, ८; १०; १०१, ३; २. १७, ३; ४१, १०; ३. २, ७; ३८, ४; ५४, १७; ५५, १[२]; ४. ३६, १; ५३, १; ५. ११, ६; १५, ३; ८. ४, ७; १९, १८; ६८, ९; ७२, ६; ८३, १; ९७, ८; ९. ९७, ४१, ११३, १; १०. ३६, ११; ५१, १; ५५, २; ४; ६६, ४; ९३, १०.

महतः १. १५६, २; १७८, ५; २. १५, १; ३. ६, ५; ४६, १; ४. २२, ५; ५. ३२, ३; ८७, ४; ७. ९८, ४; ९. ८८, ५; ९७, २९; १०. ३४, १२; ६७, १२; ७९, १.

महता १. ३२, ५; ४. १८, ७; ५. ३२, ८; ६. ४७, ५; ७. १०४, १६; ८. १, १४; १०. ४४, १.

महतां ५. ५९, ४; ८. ४७, १; १०. ३६, ११; ६५, ३.

महति ६. १८, ६; ३४, ५; ५०, ४.

महती ७. ७५, ७.

महतीः ८. ७, २२.

महते १. ५१, १३; १०४, ६; ७; १६४, २७; १६८, ९; ३. ८, २; ११; ५. २८, ३; ३२, ७; ६. ३१, ५; ८. ५९, ५; ९. ९७, ४; ५; १०. ११६, १.

महत्ऽभिः १. ७२, ९; ३. ३६, १; ४. २२, ३; ४१, २; ६. ३२, ४; ७. ७५, ७; १०. ७०, ५.

महत्ऽभ्यः १. २७, १३.

महत्ऽभ्यां ३. ७, ६.

महत्याः १०. ५५, ४.

महत्ऽसु १. ८१, १; १०२, १०.

महत्ऽभिः ७. ३७, १.

महय १. ५२, १; ३. २४, ४; ७. २३, १; ९६, १.

महऽयते ७. ३२, १९.

महयन् १. ५४, २; ३. ३, ११.

महयन् ७. ४२, ३.

महयंत ३. ३, ३.

महयंतः ४. १७, १८; ५. ३१, ४; ८. ३, १६; १०. ६५, ४.

महयंतं १. १७८, १.

महयं ७. ६१, ६.

महयमानः ३. २५, ५.

महयसे ६. १५, २.

महयाय्याय १०. १२२, ७.

महयामसि ३. ३७, ४.

महयं १०. ६५, ३.

महंसा १. १६२, १७; ५. ५९, ६; १०. ९४, १०.

महस्यं १. १५०, १.

महस्वान् १०. १३०, ४.

महा १. १६५, २; २. २४, १; ६. ४०, ४; ५२, १७; ७. १२, १; ८. ४६, १४; ९. ८८, ४.

महांसि ५. २८, ३; ६०, ४; ७. ५६, १४.

महाऽकुलः १. १६१, १.

महाऽगयं ९. ६६, २०.

महाऽग्रामः १०. ७८, ६.

महाऽधनं ९. ८६, १२.

महाऽधनस्य १०. ८४, ६.

महाऽधने १. ७, ५; ४०, ८; ११२, १७; ६. ४६, ४; १३; ५९, ७; ८. ७५, १२.

महान् १. ४, १०; ८, ५; ९, १; २७, ११; ३६, ९; १२; ५६, ३; ६३, १; ८१, ४; ९४, ५; ९५, ४; १४६, २; ३. १, ११; १९; ६, ४; ३१, ३; ३६, ४; ५; ४६, २; ५३, ९; ५५, ९; ५९, ५; ४. ७, ७; ८, २; ९, १; २१, ६; २२, १; ३०, २; ९; ३२, १; ५३, १; ५. १, २; ६. १९, १; २५, १; ३८, ३; ४५, १३; ४७, ५; ४८, ३; ७. ११, १; ३१, ७; ५२, ३; ६३, २; ८. १, २७; २, ३२; ६, १; २६; १३, १; १६, ७; ३३, ८; ५२, ५; ६०, ६; १९; ६२, १२; ६४, २; ६५, ५; ९२, ३; ९५, ४; ९८, २; १०१, ११^2; १२^2; ९. २, ६; ९, ३; ५९, ४; ६६, १६; ७७, ५; ९७, २; १०९, ४; १०. ४, २; ४६, १; ५०, ४; ७५, ९; १२०, ९; १५२, १.

महानां १. १८७, ६; ८. ६३, १; ९२, ३; ९४, ८; ९. १, ४.

महानि १. ५५, ५; २. ११, ६; १५, १; ३. ६, ५; ३४, ६; ४६, १; ४८, ३; ४. २२, ५; ६. ७, ५; ७२, १; ७. ६, २.

महान्ऽइव ८. २, १९.

महांतः १. १६६, ११; ८. २०, ८.

महांतः ५. ४१, १३; ५५, २.

महांतं १. ५१, ६; ११४, ७; ५. ३२, १; ८३, ८; ६. २१, ६; ८. १२, २३; ९. २, ४; १०. १३४, १.

महांता १. २१, ५; ६. ६७, ४; ८. २५, ४.

महांति ३. १, २०; ५. ५९, ४; १०. १११, २.

महांतौ ७. ८२, २.

महाऽपदेनं १०. ७३, २.

महां १. ६, ६; ५७, ६; ११२, १४; २. ११, ९; २२, १; २४, ११; ३. २, ३; ४९, १; ४. ५, ९; १७, ८; १९, १; २३, १; ६. ७, २; १७, ४; ५; १३; २९, १; ३८, ५; ८. ३, २०; ६५, ३; ९. ४०, ३; ६५, १; ९०, ५; १०९, ७; १०. ४६, ५; ८०, ७; ११२, ९.

महाऽमनसां १०. १०३, ९.

महाऽमह ८. २४, १०; ३३, १५; ४६, १०.

महाऽमहः १०. ११९, १२.

महाऽमहिव्रतं ९. ४८, २.

महाय्यै ८. ७०, ८.

महाऽवंदूरिणा १. १३३, २.

महाऽवंधः ५. ३४, २.

महाऽव्रंधात् ५. ८३, २.

महावसू इति महाऽवसू ७. ८२, २.

महाऽवीरं १. ३२, ६.

महाऽवैलस्थे १. १३३, ३.

महाऽव्रातः ३. ३०, ३.

महाऽसेनासः ७. ३४, १९.

महाऽहस्ती ८. ८१, १.

महि १. ४१, ७; ४३, ७; ५४, ८; ११; ६२, २; ७९, ४; ९३, ८; ११६, ६; ११९, ४; १२७, ११^2; १३०, ७; १३५, ९; १३९, ९; १४०, ५; १५१, ४; १५५, ३; १५६, २; १५९, २; १६०, ५; १६३, १; १६७, १०; २. १२, १०; २२, १; २३, ४; २४, १४; २७, ८; ३४, १४; ३. १, २२; ७, ४; ३०, १३; १४; ३१, ३; ४; ६; १२; १४^2; १५; ५४, २; ४. ३, १४; ५, ३; ९; १६, ४; ३४, ४; ५६, ५; ५. १, १०; ६, ७; १८, ५; ३२, ८; ३३, १; ५४, १; ६०, ३; ६८, ३; ८३, ५; ६. १, १०; ३, ४; ४, ७; १७, १; ७; १२; १९, १०; १२; २१, ७; ३४, ५; ४४, १८; ४७, २५; ५१, १; ६७, ४; ७०, ५; ७२, १; ७. ५, ९; ३०, १; ५३, २; ८१, १; ८२, १; १०; ९७, ३; ८. १२, ८; २०, ७; २९, १०; ३२, १४; ४६, २५; ४७, १; ५४, ८; ५५, ५; ८६, ५; ९. २, २; ४, १; ९, ९; ६१, १०; ७४, ३; ८०, २; ८३, ५; ८५, ८; ८६, १५; ३४; ९७, ५४; १००, ८; १०८, १; १०. ३, ७; ३७, ८; ५०, १; ६५, २; ८९, १५; ९३, १; १०७, १^2; ११५, १; १४०, १; १४४, ६; १६७, २; १६९, २; १७०, ३; १८५, १.

महि १. ४८, १४; १६; ७. ८१, ४; ८. ९, १७; २७, ५; ६७, १०.

महिऽकेरवः १. ४५, ४.

महिऽक्षत्रौ ५. ६८, १.

महिऽत्वनं १. १६६, १२; २. २३, ४; ४. ३६, ३; ५. ५४, ५; ५५, ४.

महिऽत्वना १. ८५, ७; ८६, ९; ४. ५३, ५; ५. ८१, ३; ६. १६, २०; ८. २४, १३; ६८, २; ९. १००, ९.

महिऽत्वं १. ८, ५; ५९, ५; ६; ६१, ९; ८७, ३; ११५, ४; १३८, १; १६६, १; २. २७, ८; ३. ३२, ९; ११; ५. ६२, २; ६. २१, २; ६७, ८; ७२, १; ७. ४०, ५; ९९, १; ९. ४८, ५; १०. ४, ४; २६, २; ७९, १.
महिऽत्वा १. ५२, १३; ६७, ५; ६८. १; ९१, २; १०९, ६; १६४, २५; २. १५, ६; ३. १, ४; ५४, १५; ४. १६, ५; ४२, ३; ५. २, ९; ५८, २; ६. २९, ५; ६७, ३; १०; ६८, ४; ७. १३, २; २०, ४; २३, ३; ५८, १; ६१, ४; ९७, ८; १००, ३; ८. २५, १८; १०. ५४, १; ५५, ५; ५६, ७; ७५, ७; ८८, ९; ८९, १; ९६, ११; १२१, ३; ४.
महिऽत्वेभिः १०. ११३, ७.
महिन ६. २६, ८.
महिनः ६. ५२, १५.
महिनस्य ६. ३३, ५; ६८, ८.
महिनां ६. ६१, १३.
महिना १. ३२, ८; ३३, ९; १२२, ११; १३९, ११; १५१, ५; १७३, ६; १८०, ९; १८६, ९; २. १, १५; १७, २; ३. ६, २; ७, १०; ३०, १३; ५९, ७; ५. ५७, ४; ८७, २; ६. ८, २; १५, १४; ६८, ९; ७. २१, ४; ९; ६०, १०; ८६, १; ९५, १; ९६, २; ८. १२, २३; ६८, ३; ७०, ६; ९२, २३; १०. २८, ७; ७०, ५; ८१, २; ८८, ७; ११९, ८; १२१, ८; १२५, ८; १२९, ३; १४७, ५.
महिनि ५. ८४, १.
महिनी इति १. १६०, २.
महिनी इति १. १६०, ५.
महिने ७. ३१, ११.
महिनऽर्तमाय १०. ११५, ६.
महिऽमघस्य १. १२२, ८.
महिमनः ६. २७, ३; १०. ५४, ३.
महिमा १. १२९, १०; १६७, ७; ४. १६, ५; ५. ८७, ६; ६. १८, १२; ५९, २; ७५, १; ७. २८, २; ३३, ८; ४५, २; ८. ३, ४; १०; १०१, ११; १०. ६६, ५; ७५, ९; ९०, ३.
महिमानः १. १६४, ५०; १०. ९०, १६; ११४, ७; ८; १२९, ५.
महिमानं १. ६१, ८; ८५, २; २. १७, २; ३५, ९; ३. ३१, १७; ३२, ७; ५. ८१, ३; ६. ७५, ६; ७. २, २; २१, ६; २२, ८; ७५, १; ९८, ३; ८. ३, ८; १३; ४६, ३; ५९, २; ५; ६५, ४; १०. ६५, २; ६९, ९; ७५, १; ११२, ४; ११३, १–३; १६८, १.
महिम्नः ७. ९९, २; १०. ५६, ४.
महिम्ना १. ५९, ७; ६. ६१, १३; १०. ८८, १४.
महिम्ने ९. ६२, २७.
महिऽरत्न १. १४१, १०.
महिऽवृधे ७. ३१, १०.
महिऽव्रत १. ४५, ३; ९. १००, ९.
महिऽव्रतः ६. ६८, ९; ९. ९७, ७.
महिऽव्रतं १०. ११५, ३.
महिष ३. ४६, २.
महिषः १. १२१, २; २. २२, १; ९. ६९, ३; ८६, ४०; ८७, ७; ९२, ६; ९६, ६; १८; १९; ९७, ४१; १०. ८, १; २८, १०; १२८, ८; १८९, २.
महिषं ४. १८, ११; ८. ६९, १५; ९. ९५, ४; ११३, ३; १०. १४०, ६.
महिषस्य १. ९५, ९; १४१, ३; ९. ८२, ३; १०. ५४, ४; ६६, १०; १२३, ४.
महिषा ५. २९, ७.
महिषाऽइव ८. ३५, ७; १०. १०६, २.
महिषाः ६. ८, ४; ७. ४४, ५; ९. ७३, २; ८६, २५; ९७, ५७; १०. ५, २; ४५, ३.
महिषाःऽइव ९. ३३, १.
महिषाणां ५. २९, ८.
महिषान् ६. १७, ११; ८. १२, ८; ७७, १०.
महिषान्ऽइव १०. ६०, ३.
महिषाय १०. ६५, ८.
महिषासः १. ६४, ७.
महिषी ५. २, २.
महिषीऽइव ५. २५, ७.
महिषीं ५. ३७, ३.
महिष्वंतं ७. ६८, ५.
महिऽस्वनीनां ८. ४६, १८.
मही १. ८, ८; १३, ९; २२, १३; १०२, ७; ११७, १९; १२१, ११; १३१, १; १४२, ९; १५७, १; १६४, ३३; २. ३३, १४; ३. ३१, ३; १३; ६१, ७; ४. १४, ३; ४१, ५; ५. ४१, १५; ४३, ८; ४७, १; ८१, १; ६. ४५, ४; ६६, ३; ७. १५, १४; ५६, ४; ८. २५, ३; ४०, ४; ४६, ३३; ९. ५, ८; ८६, ४४; १०. ६०, ९; ७७, ४; ८५, २; ९२, ४; ९६, १०.
मही इति १. ८०, ११; १५१, ५; १५९, १; ३; ३. १, ७; ३८, ३; ५५, २०; ६१, ७; ४. ५६, १; ७; ७. २, ६; ५३, १; ८७, २; ९३, ५; ८. ६, १७; ७२, १२; ९. ५, ६; ९, ३; १८, ५; ४१, ५; ६८, ३; ७४, २; १०. ३५, १; ३; ६४, १४; ८०, २; ११२, ४.
महीऽइव २. २४, १४; ८. ९०, ६; १०. १३३, ५.
महीः १. १३३, १; १४२, ६; २. ११, २; ३. २२, ४; ३०, १८; ५६, २; ५. ११, ५; ६. ४५, ३; ५७, ४; ७. ५९, २; ८७, १; ८. ३, १०; ६, १६; १२, ३; ५०, २; ६६, १०; ७०, ४; ९. २, ४; ८; ७, २; १५, ७; ६१, २२; ९९, ७; १०. १४, १; ६४, ८; ९; १०४, ९.
महीनां ३. १, १२; ५. ४५, ३; ९. १०२, १; १०. १३४, १.
महीनां ८. १९, ३१.
महीभिः ३. १, १९; ४. ३२, १; ८. २, ३२; १६, ७.
महीं १. १०२, १; १३१, ४; १४०, ५; २. १५, ५; ३३, ८; ३४, ८; ३. ३०, ९; ४. १९, ६; ३१, ७;

५. ४३, ६; ४४, ६; ८५, ५; ६; ६. ३८, १; ७. २४, ६; ३६, ८; ८. ६, २३; ९. ४१, ४; ६५, १३; १०. ३०, १; ५०, ५; ७४, ४; ९२, ५; १११, ५; ११९, ८; १४०, ५; १८८, २.

महीयते १. १८२, ३; ५. ५६, ९; ९. ११३, ६.

महीयते ९. १२, ४; १०. ८६, १०; १४६, २.

महीयंते १०. १७५, ३.

महीयमानां ४. ३०, ९.

महीयुवः ९. ६५, १; ९९, १.

महीयै १. ११३, ६.

महे १. ५३, १; १०; ५६, १; ६२, २; ७१, ५; ७६, २; ९१, ७; ११६, १३; १२७, १०; १२९, १०; १३९, ६; १५१, ३; १५५, १; १६८, १; १८०, ६; २. ३१, ३; ३. ७, ९; १०; १०, ६; ४१, ६; ५१, ८; ५४, १–३; ४. ३, ७; २५, १; ५. ३३, १; ४१, ११; ४२, ११; १३; ४८, १; ५९, २; ६६, १; ७९, १; ८७, १; ६. १, १०; २०, ११; २५, ८; ३२, १; ३४, २; ४०, ३; ४४, १३; ४५, ३०; ६८, १^{२}; ७. २४, ५; २८, ३; ३०, १; ३२, ९; ७५, २^{२}; ८२, ६; ८. १, ५; २, २९; ७, ५; १५, १३; २२, ७; २४, १०; २६, २; ४५, २४; ४६, २५; ५९, १; ६४, १२; ६७, ८; ६८, ७; ७०, ९^{२}; ९३, ७; १६; ९६, १०; ९. ९, ५; १६, ५; ४४, १; ६२, २२; ६५, ७; ६६, १३; १५; ७७, ३; ८६, ३४; ८७, ५; ९६, ३; ९७, २७; १०८, १४; १०९, ३; ११; ११०, २; ७; १०. ९, १; ४८, ८; ९१, ८; ९५, ७; ९६, १.

मह्वे ७. ९७, २.

मह्वेत १. १११, ३.

मह्वेऽनदि ८. ७४, १५.

मह्वेम १. ९४, १; ७. २, ३.

महेऽमते ८. १२, ११; ३४, ७; ४९, ७; ५०, ७.

मह्ना १. ५५, १; ७२, ९; १६४, २५; १६६, ११; १७४, ४; २. ३, २; १२, १; २८, १; ३५, २; ३. ३४, ७; ६२, १७; ४. २, १; ५. ३३, १०; ७३, ३; ८४, १; ८७, २; ६. २१, २; २४, ३; ६६, ५; ७. १२, २; १८, ८; ८. ३, ६; २०, १४; ५५, २; १००, ४; १०१, १२; १०. १, ५; ६, ७; ५५, ७; ६५, ३; ६७, १२; ८९, १; ११३, ७.

मह्नां १. २३, १५; २४, १२; ५०, १३; १०९, १; १२२, ८; १२६, ६; १६५, ११; २. २८, १०; २९, ४; ४. ५, २; ३; ४२, २; ५. ४२, १६; ५२, १०; ६. २७, ८; ४६, ९; ४७, १०; ८. १, ३२; ३३; २६, १२; ५६, २; १००, १; ९. ३२, ६; १०. ३४, १; २; ३९, ६; ४८, ३; ४९, १; ८५, ३६; ४१; १२८, १; २; ४; १६९, ४.

मह्या ४. १, ९.

मह्याः १०. ३०, ७.

मह्यै १. २४, १; २; ६. ५७, ६; ८. ७०, ९.

मा १. ४, ३; ५, १०; ११, २; १८, ३; २३, ९; २४, ११; २५, २^{२}; २७, १३; ३३, ३; ३६, १६; ३८, ५; ३९, २; ४१, ८; ४३, ८; ५३, ३; ५४, १; ७१, १०; ८२, १; ८४, २०^{२}; ८९, ९; ९१, २३; ९४, १–१४; १०४, ५; ७; ८^{४}; १०५, ३; १०९, ३; ११४, ७^{४}; ८^{४}; १२०, ८; १२१, १५; १२५, ७^{२}; १२६, ७; १३९, ५; १५८, ४^{२}; १६२, १; ११^{२}; १५; २०^{३}; १७०, २; १७८, १; १८३, ४^{४}; १८९, ४^{२}; ५^{४}; २. ७, २; ११, १; २१; १५, १०; १६, ९; १७, ९; १८, ४; ९; १९, ९; २०, ९; २३, ८; १०; १२; १६; २७, १४; १७^{२}; २८, ५^{२}; ७^{२}; ९; ११^{२}; २९, ४^{२}; ५; ७^{२}; ३०, ७; ३२, २^{३}; ३३, १; ४^{३}; ५; ४२, १; २^{२}; ३^{२}; ३. १५, ६; १६, ५^{४}; ३३, ८^{२}; १३; ३५, ५; ४१, ८; ४५, १; ५३, २; १७^{२}; १९; २०^{२}; ५५, २; ४. ३, १३^{२}; ५, २; १२, ५; १८, १; २०, १०; ३२, २०; २२; ३५, १; ४४, ५; ५. ३१, २; ३६, ४; ४०, ७; ४१, १६; ४२, १६; ५३, ८; ९^{३}; ५५, ९; ५६, ७; ६५, ६; ७०, ४^{३}; ७५, ७; ७९, ९; ६. २८, ७; ३५, ५; ४४, १०; ११^{२}; १२; ४७, ९; ४८, १७^{२}; ५१, ६; ७^{२}; ५२, १४; ५९, ७; ६१, १४^{३}; ७५, १६; ७. १, ११^{२}; १९^{६}; २१^{२}, २२^{२}; ४, ४; ६^{२}; ७; ९, ५; १९; ७; २१, ५; २२, ६; २५, १; ३१, ५; ३२, ९; २७^{२}; ३४, १७; ३६, ७; ४०, ६; ४३, ३; ४६, ३; ४^{३}; ५०, १^{२}; ५२, २^{२}; ५६, ९; २१^{२}; ५७, ४; ५९, १०; १२; ६०, ८; ६२, ४^{२}; ६९, ६; ७३, ४; ७५, ८; ८८, ६; ८९, ५; ९३, ८; ९४, ३^{३}; ८; १००, ६; १०४, ७; २३; २४; ८. १, १^{२}; १३; २०; २, १५^{२}; १९; ३, २; ४, ७^{२}; ८, १३; २०, १^{२}; २१, १५; १६^{२}; २२, १४; ३०, ३; ३३, १९^{२}; ४५, २३^{२}; ३१; ३४^{३}; ३६^{२}; ४८, ८; १४^{२}; ६०, ८^{२}; २०^{२}; ६५, १०; ६६, १५; ६७, ८; ९; २०; ७१, ७; ७३, १५; ७५, ८; ९; १२; ७९, ८^{३}; ८०, ८; ८१, ६; ८६, १; ९२, ३१; ९६, १२; ९७, २; ७; १०१, १५; १०३, १२; ९. ७२, ८; ८१, ३; ८५, १; ११४, ४; १०. १५, ६; १६, १^{४}; ८; १८, १^{२}; ४; ११; १९, १; २२, १२; १५; २५, ७; २७, २४; ३४, १३; १४; ३६, २; ३७, ६; ५४, ५; ५७, १^{३}; ६२, ११; ६९, ५; ८५, ३२; ४२; ८७, ९; १९; ९५, १५^{३}; ९७, २०; १०१, ८; १०६, २; १०८, ९; १२०, ४;

१२१, ९; १२८, ४; ५[२]; ८[२]; १४२, ३; १६०, १; १६५, ३; १७३, १; २; १७८, २[२].

मा **१.** २३, २३; २४; ४८, २; १०५, ७; ८; १८; १२०, ११; १२२, १५; १२६, ३; १५८, ५; १६४, २१; ३७; १६५, ११; १२; १७९, ४; **२.** २८, ६; २९, ५[२]; ३०, ७[२]; ३३, ६; ७; **३.** १, १; ३२, १४; ४३, ५[२]; **४.** ४, ११; १५, ७; २६, १; २७, १; ४२, ६[२]; **५.** २७, ५; ३०, ९; १३; ३३, ८[२]; ४०, ७; ४२, १५; **६.** ४७, १०; ४८, १६; ५२, ४[२]; ५९, ८; **७.** १८, २३[२]; ३३, १; ५९, ७; ८३, ५; ८८, २; १०१, ६; १०४, ८; १५; १६; **८.** १०, ५; ४६, ३०; ४८, ५[२]; ६; १०; ६८, १४; ९७, १५; १००, १; ४[२]; ५; १०१, १६; **९.** ६७, २७[२]; **१०.** १०, ७; १७, १४; २८, ६; २९, ३; ३३, १; ५; ३४, १; २; ३५, ८; ४२, ३; ४८, ४; ५; ७; ११; ४९, ५; ७; ५१, २; ४; ५२, १; ८३, ५; ६; ८७, १७; ९५, ५; १३; ९७, १६; ११९, २; ४; १२४, ५; १२५, ३; १२७, ७; १२८, ९; १६६, १.

मांश्चत्वे **९.** ९७, ५४.

मांश्चत्वे **९.** ९७, ५२.

मांसऽभिक्षां **१.** १६२, १२.

मांसं **१.** १६१, १०.

मांस्पर्चन्याः **१.** १६२, १३.

माः **४.** ३३, ४; **५.** २९, ८.

मार्किः **१.** १४७, ५; **३.** ३६, ९; **४.** ४, ३; **६.** ५४, ७; ७१, ३; **८.** ५, ३९; ६७, ११; ७१, ८; **९.** ८५, ८; **१०.** ११, ९; २३, ७; १००, ७.

माकी इति **८.** २, ४२.

माकीनया **८.** २७, ८.

माकीं **६.** ५४, ७[२]; **८.** ४५, २३.

माघोनं **४.** ४३, ४; **८.** ५४, ५; **१०.** १०७, १.

माघोने **१०.** ६६, २.

मातः **१.** १८५, ११; **६.** ५१, ५.

मातरः **१.** ९२, १; **३.** ३१, २; ४१, ५; **५.** ४७, ६; **६.** ४५, २५; **८.** ८९, ४; ९५, १; ९६, १; १०२, १७; **९.** १२, २; १९, ४; ३३, ५; ८६, ३६; १००, १; ७; १०२, ४; **१०.** ९, २; १७, १०; ६४, ९; ७५, ४; ९१, ६; १२३, ३.

मातरः **१०.** ९७, ४.

मातरं **१.** २४, १; २; ११०, ८; १११, १; ११४, ७; १२१, २; १६३, १३; **३.** ४८, ३; **४.** १८, १; २; १२; **५.** ३४, ४; ५२, १६; **६.** ७२, २; **७.** ४३, ३; **८.** ४५, ४; ७७, १; १०३, २; **१०.** १८, १०; ५४, ३; ६२, ३; ८८, १५; ९४, १४; ११४, ४; १४६, ६; १७६, १; १८९, १.

मातरा **१.** १२२, ४; १४०, ३; १४२, ७; १५५, ३; १५९, ३; **३.** १, ७; ५, ७; ७, १; ३३, १; ३; **४.** २२, ४; **५.** ५, ६; **६.** १७, ७; ३२, २; **७.** २, ५; ७, ३; **८.** ९९, ६; **९.** ९, ३; ६८, ४; ७०, ६; ७५, ४; ८५, १२; १०२, ७; **१०.** १, ७; ३५, ३; ५९, ८; ६४, १४; ७९, ४; १२०, ७; १४०, २.

मातराऽइव **९.** १८, ५.

मातरापितरा **४.** ६, ७.

मातरि **३.** २९, ११; **५.** ७८, ९.

मातरिभ्वरीः **१०.** १२०, ९.

मातरिश्वः **१०.** ८८, १९.

मातरिश्वना **९.** ६७, ३१.

मातरिश्वनि **८.** ५२, २.

मातरिश्वने **१.** ३१, ३; १४३, २; **१०.** ४८, २.

मातरिश्वा **१.** ६०, १; ७१, ४; ९३, ६; ९६, ४; १२८, २; १४१, ३; १४८, १; १९०, २; **३.** २, १३; ५, ९; १०; ९, ५; २९, ११; **६.** ८, ४; **१०.** ४६, ९; ८५, ४७; १०५, ६; १०९, १; ११४, १.

मातरिश्वान **१.** १६४, ४६; **३.** २६, २.

मातरौ **१०.** ११५, १.

मातली **१०.** १४, ३.

मातवै **१.** १६४, २८.

माता **८.** ४१, ४.

माता **१.** ३८, ८; ७२, ९; ८९, ४; १०; ११३, १९; १६०, २; १६४, ८; ९; ३३; १८५, १०; १९१, ६; **२.** ३८, ५; **३.** ४६, ५; ४८, २; ५५, ४; १२; **४.** १८, ५; १०; ११; ५२, २; ३; **५.** २, १; २; ७, ८; ४१, १५; १९; ४२, २; १६; ४३, २; ४५, २; ६; ४७, १; **६.** १, ५; ६६, ३; ७०, ६; **७.** ५५, ५; ७७, २; ९८, ३; १०१, ३; **८.** १, ६; २५, ३; ४७, ९; ९४, १; ९८, ११; १०१, १५; **१०.** ४, ३; १७, १; १८, ११; २७, १४; १६; ३२, ४; ३४, ४; १०; ३६, ३; ६०, ७; ६१, २०; ६३, ३; ६४, १०; ७३, १; ९७, ९; ११४, ४; १३२, ६.

माताऽइव **५.** १५, ४; **६.** ७५, ४.

मातुः **१.** ३७, ९; ६१, ७; १४०, ९; १५९, २; १६४, ३२; **२.** ५, ६; **३.** ८, १; २९, १४; **४.** १, १६; २, १५; ५, १०; १७, १२; **५.** १, ६; १९, १; ४७, ५; **६.** १६, ३५; २०, ८; ५५, ५; **७.** ४, २; ८१, ४; **८.** ८३, ८; **९.** ६९, १; ७३, ५; ८९, १; **१०.** २०, २; ३२, ८; ७९, ३.

मातृऽतमाः **१.** १५८, ५; **६.** ५०, ७.

मातृऽतमां **३.** ३३, ३.

मातृऽभिः **२.** ११,८; **८.** ७२, १४; **९.** ९३, २; १०४, २; १०५, २; १११, २.

मातृऽभ्यः **१.** ९५, ७; **१०.** १, २.

मातृमृष्टाऽइव **१.** १२३, ११.

मातृषु **१.** १४१, २; **३.** २३, ३; **४.** ७, ६; **९.** ७०, ४.

मातॄः **१.** ९५, ४; १४१, ५; १६४, १०; **३.** ९, २.

मातॄन् **१०.** ३५ २.

मातृऽभिः २. २४, ५.
मात्रंया ७. ९९, १; १०. ७०, ५.
मात्रां २. २८, ५.
मात्राभिः ३. ३८, ३; ४६, ३.
मात्रां १०. ७१, ११.
मात्रे ८. ६९, १५.
मात्रे इति १०. २९, ६.
मात्रोः ३. २, २; ५. ११, ३; ७. ३, ९; ८. ६०, १५.
मार्दनं ७. २१, १.
मादयध्यै १. १६७, १; ६. १९, ६; २२, ३; ६०, १३.
मादयध्वं १. ८५, ६; ७. ३८, ८; ४८, १.
मादयध्वं ३. ५४, १२; ४. ३४, २; ८; ६. ५२, १३; १७.
मादयन् ९. ८०, ५; ८४, ३.
मादयंतां ३. ४, ११; ७. ११, ५; ३९, ५; ५१, २.
मादयंति १०. ३४, १.
मादयंतु ७. २३, ५.
मादयंते ३. ५४, २; १०. १२, ७; १५, १४.
मादयंते १. ५९, १; ७. ११, १; १०. १६, ८.
मादयसे ८. ४, २.
मादयसे ८. ५२, १.
मादयस्व १. ८१, ८; १०१, १०; २. ३, ११; ३. ६, ९; ६. ४१, ५; ८. ९७, ६; १०३, १४.
मादयस्व १. १०१, ९; २. १८, ७; ३. ३२, १; ७. २३, ५; २९, २; ९२, ५; १०. १४, ४; ५; १७, ८; १०४, ३; ११२, ३; ११६, २.
मादयाते ७. ४७, २.
मादयाध्वे ७. ५९, ६.
मादयाध्वै १. ३७, १४; १६१, ८.
मादयासे १. १०१, ८; ८. ६५, २.
मादयासे १०. ९५, १८.
मादयित्नवे ९. १०१, १.
मादयिष्णवः १. १४, ४; ८. ८२, २.
मादयेते इति १०. ४०, १४.
मादयेथां ४. ४९, ६.
मादयेथां १. १०९, ५; १८४, २; ४. १४, ४; ६. ६८, ११.
मादयेथे इति १. १०८, १२.
मादयैते इति ४. ४१, ३.
माध्यंदिनं ३. ३२, १; ४. ३५, ७.
माध्यंदिनस्य ३. ५२, ५; ८. ३७, १; १०. १७९, ३.
माध्यंदिने ३. २८, ४; ३२, ३; ५. ४०, ४; ६. ४७, ६.
माध्वी इति ५. ७५, १.
माध्वी इति १. १८४, ४; ४. ४३, ४; ५; ६. ६३, ८; ७. ६७, ४; ७; ७१, २.
माध्वीः १. ९०. ६; ८.
मानः ७. ३३, १३.
मानं १. ३९, १; १००, १४; ७. ८८, ५; ८. ६३, २.
मानं १०. १४४, ५.
मानवं १०. ६२, १.
मानवस्यते १. १४०, ४.
मानवात् ८. ३०, ३.
मानवी १०. ८६, २३.
मानवी इति ९. ९८, ९.
मानवेभ्यः ४. ५४, १.
मानस्य १. १८९, ८; ८. ६३, ७.
मानात् ९. ७३, ६.
मानासः १. १७१, ५; १८२, ८.
मानुष १. ८४, २०; ३. ९, ६.
मानुषः १. ३७, ७; ४४, १०; १५३, ३; २. ११, १०; ६. २, ३; ८. ६२, ६; १०. ७७, ७; ९३, ८; ९५, ८.
मानुषऽप्रधनाः १. ५२, ९.
मानुषं ५. ६६, २.
मानुषस्य १. ७०, १; १२१, ४; १०. २०, ५.
मानुषा १. ५१, १; १०३, ४; १३१, १[2]; १४४, ४; २. २, २; ९; ५. ५२, ४; ६. १२, २; १६, २३; ७. ४, १; ८. २३, २६; ४६, १२; ६२, ९; ९. १२, ७; १०. १४०, ६.
मानुषाः १. ३८, १०; ३९, ६; १६२, ४; १०. १३, २; १२२, ७.
मानुषाणां १. ८४, २; १२७, ८; १२८, ७; ४. १, २०; ८, ८; ९, ५; ५. ७, ३; ६. १, ५; १८, ७; १९, ६; ७. १०, ३; ६२, १; ६३, १; ७७, १; ८. २३, २५; ४१, १; ९. ६१, ११.
मानुषात् २. ३, ३.
मानुषान् १. ४८, ७; ५०, ५; ११३, ९; ८. ९, २; १९, ३५; १०. ११५, ७.
मानुषाय १. १२३, १.
मानुषासः १. ६०, ३; ७. ७, ४; ११, २; १०. ४६, १०.
मानुषि ७. ७५, २.
मानुषी १. ७२, ८.
मानुषीः ३. २, १०; ६, ३; ५. ८, ३; ४५, १; ६. ६५, १; ७. ५, २; ७९, १; ९. ६३, ७; १०. ६९, ९; ८०, ६; ८३, २.
मानुषीः ६. ५०, ७.
मानुषीणां १. ५९, ५; ३. ११, ५; ३४, २; ५. १, ९; ४, ३; ९, ३; ६. १८, २; ४८, ८.
मानुषीषु २. ४, ३; ३. ५, ३; ४. ६, ७; ८; ९, २; ७. ६७, ७; ९. ३८, ४; १०. १, ४.
मानुषे १. ४८, ११; १२८, ७; ३. २३, ४; ५. १४, २; २१, २; ६. १६, १; ७. १८, ९; ८. ६४, १०; १०. ११८, ९.
मानुषेभिः ७. ३८, १; १०. १२५, ५.
मानुषेभ्यः ४. ५४, २.
मानुषेषु १. २५, १५; ५८, ६; ५९, ३; ६०, ४; ६. ५४, ३; ५. १३, ३; ७. २, ७; २२, ६; १०. ४६, ४.
माने १०. २७, २३.
मानेन १. ११७, ११.
मानेनऽइव ५. ८५, ५.
मानेभिः १. १८४, ५.
मानेभ्यः १. १६९, ८.
मानैः २. १५, ३.
मांदायंस्व १. १६५, १५; १६६, १५; १६७, ११; १६८, १०.

मान्यमानं ७. १८, २०.
मान्यस्य १. १६५, १४; १५; १६६, १५; १६७, ११; १६८, १०; १७७, ५; १८४, ४.
मां १. १५८, ४²; १६५, ६; १८५, ९²; ४. २७, २; ३९, १; ४०, १; ४२, ५²; ५. २, ३; ३०, ८; ४०, ७; ६. ५२, ४; ७. ४९, १; ५०, १²; ८३, ३; ८. ६, ३२; ७४, १४; ९. ६७, २१; २५; २७; १०७, १९; ११३, ७; ८; १०. १८, १४; २७, ५; २८, ६; ३३, १; ४८, १; ३; ४९, २; ५२, ४; ८३, ६; ८६, ९; ९८, २²; १२५, ४; १४५, ६; १८३, २.
मामकः १०. १५९, १.
मामकं १०. १७, १४.
मामकानां १०. १०३, १०.
मामतेयः १. १५८, ६.
मामतेयं १. १४७, ३; १५२, ६.
मायया १. ८०, ७; १४४, १; १६०, ३; २. १७, ५; ३. २७, ७; ४. ३०, १२; २१; ५. ६३, ३; ७; ६. २२, ६; ७. १०४, २४; ८. २३, १५; ४१, ३; ९. ७३, ५; ९; ८३, ३; १०. ७१, ५; ८५, १८; १७७, १.
मायवः १०. ९३, १५.
माया ३. ६१, ७; ५. ६३, ४; १०. ५४, २.
मायाः १. ३२, ४; ११७, ३; २. ११, १०; २७, १६; ३. २०, ३; ५३, ८; ५. २, ९; ३१, ७; ४०, ६; ८; ६. १८, ९; २०, ४; २२, ९; ४४, २२; ४५, ९; ५८, १; ७. १, १०; ९८, ५; ९९, ४; ८. ४१, ८; १०. ५३, ९; ७३, ५; ९९, २; १११, ६.
मायाभिः १. ११, ७; ३३, १०; ५१, ५; १५१, ९; ३. ३४, ६; ६०, १; ५. ३०, ६; ४४, २; ७८, ६; ६. ४७, १८; ६३, ५; ८. १४, १४; १०. १४७, २.
मायां ५. ८५, ५; ६; १०. ८८, ६.
मायाऽवान् ४. १६, ९.
मायाऽविनः ९. ८३, ३.
मायाऽविनं २. ११, ९.
मायाऽविना १०. २४, ४.
मायिनः १. ३९, २; ५१, ५; ५४, ४; ६४, ७; १५९, ४; २. ११, १०; ३. ३८, ७; ९; ५६, १; ५. ४४, ११; ६. ६१, ३; ७. ८२, ३; ८. ३, १९; २३, १४; १०. १३८, ३.
मायिनं १. ११, ७; ५३, ७; ५६, ३; ८०, ७; २. ११, ५; ५. ३०, ६; ५८, २; ६. ४८, १४; ८. ७६, १; १०. १४७, २.
मायिना ६. ६३, ५.
मायिनां १. ३२, ४; ३. २०, ३; ३४, ३.
मायिनि ५. ४८, ३.
मायिनी ५. ४८, १.
मायिनी इति १०. ५, ३.
मायी ७. २८, ४; १०. ९९, १०; १४७, ५.
मायुः ७. १०३, २.
मायुं १. १६४, २८; २९; १०. ९५, ३.
मारुत ५. ४६, २.
मारुतऽअश्वस्य ५. ३३, ९.
मारुतः ५. ६१, १३.
मारुतं १. १४, ३; ३७, १; ५; ३८, १५; ६४, १२; १०६, १; १२७, ६; २. १, ६; ११, १४; ३०, ११; ४. ६, १०; ५. ४२, १५; ४६, ५; ५२, ८; १३; १४; ५३, १०; ५६, ८; ५८, १; ६. ४८, १५; ६६, ५; ११; ७. ५७, १; ८. १५, ९; ९४, १२; ९. ८८, ७; ९०, ५; ९७, ४२; १०. ३६, ७.
मारुतस्य १. ८७, ६; १५६, ४; ८. २०, २३.
मारुताय ५. ५४, १; ६. ४८, १२; ६६, ९; ८. २०, ९.
मारुतीः ८. १२, २९.
मारुतेन २. ३१, ३; ३. ३२, २.
मर्जाल्यः ५. १, ८.
मार्ज्मि २. ३५, १२.
मार्डीकं १. ७९, ९; ७. ८२, ८; ९१, २.
मार्डीके ४. १८, १२.
मार्डीकेभिः ८. ७, ३०.
मार्तांडः २. ३८, ८.
मार्तांडं १०. ७२, ८; ९.
माऽवतः १. १७, २; १२९, ११; १४२, २.
माऽवते १. ८, ९; ४. १६, १६; ६. ६५, ४; ७. ३२, २१; ८. ८८, ३; १०. ५०, २.
मार्सः १०. ८५, ५.
मासः १. २५, ८; ४. १८, ४; ५. ४५, ७; ११; ७. ९१, २.
मासं ७. ६६, ११.
मासा ६. ३४, ४.
मासाऽइव १०. १३८, ४.
मासाः ३. ३२, ९; ६. २४, ७; ३८, ४; ७. ६१, ४; १०. ८९, १३.
मासान् ३. ३१, ९; ५. ७८, ९.
मासां १०. १३८, ६.
मासि १०. १८४, ३.
मासि १. ९२, ७; १४२, २; २. १७, ७; ८. ७१, ९; ९. ७६, ३; १०. १२, ७.
मासिऽमासि १०. ५२, ३.
मास्व ९. ७२, ९; ९३, ५.
माहि ४. २२, १०; ७. २६, ५; १०. २८, १२.
माहिनः १. ५६, ६; १६५, ३; २. १९, ३; १०. २६, १; ९.
माहिनं १. १५१, ९; ३. ३६, ९; ४. १७, २०; ८. ६२, १; ९. ८२, २.
माहिनऽवान् ३. ३९, ४; ५६, ३.
माहिनस्य ८. ७१, ९.
माहिना १. १८०, ५; ३. ७, ५.
माहिनाय १. ६१, १.
माहिनायाः ५. ४५, ८.
माहिने इति ३. ६, ४.
माहिनानां १०. ६०, १.
मितः १०. १८, १२.

मितऽज्ञंवः ३. ५९, ३; ७. ८२, ४.

मितज्ञुंऽभिः ६. ३२, ३; ७. ९५, ४.

मितऽद्रंवः ७. ३८, ७; १०. ६४, ६.

मितऽद्रुंः ४. ६, ५; ७. ७, १.

मितऽद्रौ ९. ९४, ४.

मितऽमेंधाभिः ८. ५३, ५.

मितयं: ७. ३५, ७.

मिता १. १७३, ३.

मिताऽइंव ९. ९७, १.

मिताःऽइंव ४. ५१, २.

मित्रे १. १५१, ६; २. २७, १४; २९, १; ४. १, १८; ५. ४६, २; ६२, ५; ६७, १; २; ७०, १; ७१, १–३; ७. ५९, १; ६६, ३; ८. १९, ३५; ४७, १.

मित्र १. १२२, ७; २. २७, ६; ८; ३. ५९, २; ४. ५५, १; ५. ६२, ८; ६४, ५; ६७, ५; ६९, १; २; ७. ६४, ५; ६६, ९; ८. १८, २१; २७, ६; १५; १०. ६४, १२.

मित्रऽअतिथ्रेः १०. ३३, ७.

मित्रः १. २३, ६; २६, ४; ३६, ४; ४०, ५; ४१, १; ४३, ३; ४४, १३; ६७, १; ७५, ४; ७७, ३; ७९, ३; ९०, १; ९; ९१, ३; ९४, १३; १६; ९५, ११; ९६, ९; ९८, ३; १००, १९; १०१, ११; १०२, ११; १०३, ८; १०५, १९; १०६, ७; १०७, ३; १०८, १३; १०९, ८; ११०, ९; १११, ५; ११२, २५; ११३, २०; ११४, ११; ११५, ६; १३६, ३; ७; १४१, ९; १५६, १; १६२, १; १८६, २; १९०, ६; २. १, ४; २७, १; २; ३८, ९; ३. ४, २; ६; ५, ३; ४[४]; ९; १४, ४; ५४, १०; ५९, १[३]; ४; ७; ९; ४. ६, ७; १३, २; ५५, ५; ५. ३, १; १०, २; २६, ९; ४०, ७; ४६, ५; ४९, ३; ६५, १; ४; ६८, २; ७२, ३; ८१, ४; ६. २, १; ८, ३; १३, २; २४, ५; ४४, ७; ४९, १; ५१, १०; ५२, ११; ६२, ९; ७. ९, ३; १२, ३; ३४, २५; ३६, २; ३९, ७; ४०, २; ४; ५१, २; ५६, २५[२]; ६०, ४–६; ८; ६२, ३; ६; ६४, १; ६६, ४; ११; १२; १७; १८; ८२, ५; १०; ८. १५, ९; २५, १३; २६, ११; २७, १७; ३१, १३; ४६, ४; ६७, २; ९४, ५; ९. २, ६; ६४, २४; ७७, ५; ८१, ४; १०. १२, ५; ८; २२, १; २; २९, ४; ३१, ९; ३६, १; ६५, १; ९; ६८, २; ७९, ७; ९२, ४; ६; ९३, ४; ९८, १; १०९, २; १२६, १; १४७, ५.

मित्रःऽइंव २. ४, १.

मित्रऽकुंवः १०. ८९, १४.

मित्रऽधिंतये १. १२०, ९.

मित्रऽधिंतानि १०. १००, ४.

मित्रऽपते १. १७०, ५.

मित्रऽमहः १. ४४, १२; ५०, ११; ५८, ८; २. १, ५; ४. ४, १५; ६. २, ११; ५, ४; ७. ५, ६; ८. १९, २५; ४४, १४; ६०, ७; १०. ३७, ७; ११०, १.

मित्रऽमंहाः ६. ३, ६.

मित्रंऽइंव ८. ८४, १; १०. ७, ५.

मित्रऽयुजंः १. १८६, ८.

मित्रऽयुवंः १. १७३, १०.

मित्रं १. २, ७; २३, ४; ३८, १३; ५८, ६; ८९, ३; ९६, १; १०६, १; १२९, १०; १४३, ७; १५१, १; १६४, ४६; २. २, ३; ४, ३; ११, १४; ४. २, ४; ३३, १०; ३९, ४; ५. ३, २; १६, १; ४२, १; ५२, १४; ६४, १; ६. १५, २; २१, ९; ४८, १; ५०, १; ५१, ३; ७. १८, १०; ३९, ५; ६५, १; ६६, ७; ९३, ७; ८. १८, २०; २३, ८; ३१, १४; ७४, २; ९६, ६; १०२, १२; ९. ९०, ५; ९७, ३०; १०. ८, ४; २०, २; २७, १२; ३४, १४; ६३, ९; ८७, १; ८९, ८; ९; १०८, ३.

मित्रयोंः ६. ५१, १; ७. ६६, १.

मित्रंराजाना ५. ६२, ३.

मित्रस्यं १. १४, १०; २१, ३; ४१, ७; ९४, १२; ११५, १; ५; १३६, २; १५२, ४; २. २७, ७; ३. ५५; ६; ५९, ३; ६; ६१, ७; ४. ५, ४; ५५, ७; ५६, ७; ५. ९, ६; ६४, ३; ६५, ४; ५; ६. ४७, २८; ७. ६१, ४; ६२, ४; ६३, १; ८. १२, १२; १९, ४; २५, १७; ४७, ९; ५२, ३; ९. ८६, ११; १०७, १५; १०. १०, ६; ३०, १; ३६, ३; १३; ३७, १; ८९, ८; १८५, १.

मित्रां ५. ६६, ६.

मित्रा १. १४, ३; ३६, १७; ८. २५, २.

मित्रा ५. ६५, ६.

मित्राऽइंव १०. १०६, ५.

मित्राः ९. १०१, १०.

मित्राणां १. १७०, ५.

मित्रायं १. १२९, ३; १३६, ४–६; १३७, २; २. ३४, ४; ३. ५९, १; ५; ८; ४. ३, ५; ५. ६८, १; ७. ६०, १; ६२, २; ८. १०१, ५; ९. ७०, ८; ८५, ६; १००, ५; १०४, ३; १०८, १६; १०९, १; १०. ६५, ५; ८५, १७; ११३, ५.

मित्रावरुंणयोः १०. १३०, ५.

मित्रावरुंणऽवंतौ ८. ३५, १३.

मित्रांवरुणा १. १५, ६; ५. ६३, २.

मित्रावरुंणा १. २, ९; २३, ५; ७१, ९; ७५, ५; १११, ४; ३. २०, ५; ५. ४६, ३; ६३, ३; ६. ११, १; ४९, १; ६७, १; ७. ३३, १०; ४१, १; ४२, ५; ८. २३, ३०; २५, ४; ९. ७, ८; ९७, ४२; ४९; १०८, १४; १०. ६१, १७; ६४, ५; १२५, १.

मित्रावरुणा १. १२२, ६; १५; १३७, १; ३; १५२, १; ३; ७; १५३, १–३; २. २७, ५; २९, ३; ३१, १; ४१, ४; ३. ६२, १६; ४. ३९, २; ५; ५. ४७, ७; ५१, १४; ६२, २; ६३, १; ४; ५; ७; ६४, ४; ६७, ३; ९; ६९, ३; ४; ७. ३६, २; ५०, १; ५२, १; ६०, २; ३;

६१, ३; ६; ६२, ५; ६३, ५; ६४, २; ४; ६५, २–४; ६६, १९; ८. ७२, १७; १०१, ३; १०. ५१, २; १३२, २.
मित्रावरुणाभ्यां ५. ५१, ९.
मित्रावरुणा १. ३५, १; १६७, ८; ७. ३५, ४; ८. १०१, १; १०. ९३, ६.
मित्रावरुणौ १. २, ८; १२२, ९; १३९, २; ५. ४१, १; ६२, ९; ६३, ६; ६. ६७, २; ११; ७. ६०, १२; ६१, २.
मित्रासः १. १५१, २; ३. ५८, ४; ७. ३८, ४; १०. ११५, ७.
मित्रिणः १. १७८, ४; ८. ३५, १२.
मित्रियः ८. १९, ८.
मित्रियात् ४. ५५, ५.
मित्रे १. १५२, ५; ५. ४२, २; ४९, ५; ७२, १; ९. ६१, ९; १०. ३६, १२; १३२, ५.
मित्रेण ४. ३९, ३; ६. ३, १.
मित्रेरून् १. १७४, ६.
मित्र्यः २. ६, ७.
मित्र्यं ५. ८५, ७.
मित्वा १०. ५, ३.
मिथः १. २६, ९; ६८, ४; ११९, ३; १४४, ३; ४. २४, ३; ४; ५६, ६; ७. ३८, ५; ५६, २; ३; ७६, ५; ८. २०, २१; ७२, १४; १०. ६५, २; ६८, १०.
मिथःऽअवद्यपेभिः १०. ६७, ८.
मिथःऽतुरः ७. २६, ४; १०. ७६, ६.
मिथःऽतुरा ६. ४९, ३.
मिथती इति ७. ९३, ५.
मिथतीः ६. २५, २; ९.
मिथत्या ७. ४८, ३.
मिथस्पृध्याऽइव १. १६६, ९.
मिथु १. १६२, २०; ६. १८, ८.
मिथुऽकृतं १०. १०२, १.
मिथुऽदृशा १. २९, ३; २. ३१, ५.
मिथुना १. ८३, ३; १४४, ४; १५९, ४; १७३, २; ३. ३९, ३; ७. १०४, २३; ८. ३३, १८; १०. १०, ९; १७, २; ४०, १२; ८७, १३; २४; ९९, ५.
मिथुनाः १. १३१, ३; ४. ४५, १.
मिथुनानि ३. ५४, ७.
मिथुनासः १. १६४, ११; ५. ४३, १५; ९. ९७, ३७.
मिथुनौ १. १७९, ३; १०. ८८, ११.
मिथुया ७. १०४, १३.
मिनत् ५. २, १.
मिनत् ४. ३०, २३; ७. ३२, ५; ८. २८, ४.
मिनतीः १०. १०८, ११.
मिनन् २. १३, ३.
मिनन् ९. ६१, २७.
मिनन्ता १. ११७, ३.
मिनन्ति २. ३८, ९; ४. ५, ४; ५. ८२, २; ६. ६७, ९; ८. ९३, ११; १०. ८३, ८; ९.
मिनन्ति १. ६९, ४; २. २४, १२; ३८, ७; ३. २८, ४; ३२, ८; ५६, १; ५. ५९, ५; ६९, ४; ६. २१, ३; ७. ३१, ११; ४७, ३; ७६, ५; १०३, ९; १०. १०, ५; ९४, १३.
मिनवाम ५. ४५, ५.
मिनाति १. १७९, १; ५. ७, ४; ७. ३६, ४; ८४, ४.
मिनाति १. ७१, १०; १२३, ९; १२४, ३; २. १२, ५; ३. ३०, १२; ६. ३०, २; ८. ८८, ३; ९. ८६, १६; ९७, ३०.
मिनानः ५. ४२, १३.
मिनामि १०. २५, ३; ४८, ११.
मिनीमसि १. २५, १.
मिनीमसि १०. १३४, ७.
मिनोतु १०. १८, १३.
मिन्वन् १०. २०, ५.
मिन्वन् ३. ३१, १२.
मिमते १. १६४, २४; ९. ९७, ९; १०. ११४, ५.
मिमन्ति ९. ३३, ४.
मिमय २. २९, ५.
मिमाति १. १६४, २८; २९; ९. ६४, १९.
मिमाति १. ३८, ८; ९. ६९, ४.
मिमातु ५. ५९, ८.
मिमाते इति ७. ८२, ६.
मिमाथां ४. ४४, ६.
मिमाथां ४. ४१, ४.
मिमानः १. ५०, ७; २. १७, २; १०. ८४, २.
मिमानं ५. २, ३.
मिमाना ६. ६२, २; ७. १८, १५; १०. ११०, ७.
मिमानाः १०. ५६, ५.
मिमाने इति १. १४६, ३.
मिमाय १. १६४, ४१; २. १५, ३; ३. ५३, १५; ५५, १३; ७. १८, १६.
मिमिक्ष ९. १०७, ६.
मिमिक्षः ६. ३४, ४.
मिमिक्षतं १. २२, ३; ३४, ३; ४७, ४; १५७, ४.
मिमिक्षतां १. २२, १३; ६. ७०, ५.
मिमिक्षति १. १४२, ३.
मिमिक्षतुः ८. ६१, १८.
मिमिक्षन् ७. २०, ४.
मिमिक्षिरे १. ८७, ६; १०. ९६, ३.
मिमिक्षुः ६. २९, २; १०. १०४, २.
मिमिक्षुः १. १६५, १; १६७, ४; ५. ५८, ५; ६. २९, ३.
मिमिक्षुं ३. ५०, ३.
मिमिक्षे २. ३, ११.
मिमिक्ष्व १. ४८, १६.
मिमीतः ५. ७६, २.
मिमीतं १. १२०, ९.
मिमीतं १. १२०, ९.
मिमीतां ५. ५१, ११.
मिमीते ८. १२, १०–१२; १३, ३०; ९. १०२, ३.
मिमीते १. १६४, २४; ३. १, ५; १०. ७१, ११.
मिमीयाः १०. ५६, २.
मिमीयात् १०. १०, ९.
मिमीहि १. ३८, १४.
मिमीहि ३. १, १५; ५४, २२; ५. ४, २; ६. १९, ३; ७. १९, ११.
मिमृक्षुः १. ६४, ४.
मिमे १०. १३, ३; १२४, ३.

मिमेथ १०. ३४, २.
मिम्यक्ष १. १६७, ३; ६. ५०, ५; १०. ४४, २.
मियेधः १. १७७, ४; ३. ३२, १२; १०. ७०, २.
मियेधे ३. १९, १; ५; ७. १, १७.
मियेधैः ६. ५१, १२.
मियेध्य १. २६, १; ३६, ९; ४४, ५.
मिश्रा १०. ९५, १.
मिषतः १०. १९०, २.
मिषति ३. २९, १४.
मिषंतं १. १६४, २८.
मिषंता ८. २५, ९.
मिषंति ९. ७३, ४; १०. १०, ८.
मिहः १. ७९, २; ३. ३१, २०; १०. ७३, ५.
मिहः १. ३७, ११; ५. ३२, ४.
मिहं १. ३२, १३; ३८, ७; १४१, १३; २. ३०, ३; ८. ७, ४; १०. ३१, ९.
मिहे १. ६४, ६.
मीढ्वः २. ३३, १४; ३. १६, ३; ८. ७९, ९.
मीढ्वः १. ११४, ३; ८. ७६, ७; ९. ६१, २३; ८५, ४; ११३, २; १०. ८५, २५; ४५.
मीढ्वांसः ८. २५, १४.
मीढ्वान् १. २७, २; २. २४, १; ९. ७४, ७; ९७, ३९; १०७, ७.
मीमयत् १०. २७, २२.
मीमृषः १. ३१, १६.
मीयंते २. ८, ३.
मीयमानः ३. ८, ३.
मीळ्हुःऽतमाय १. ४३, १.
मीळ्हुषः १. १५५, ४; १६९, ६; १७३, १२; २. ८, १; ४. १५, ५; ६. ६६, ३; ७. १६, ३; ४०, ५; ५८, ५; ८. २०, १८; १०२, १५; १०. १८८, २.
मीळ्हुषा ८. २०, ३.
मीळ्हुषी ५. ५६, ९.
मीळ्हुषे १. १२२, १; १३६, ६[2]; ४. ३, ५; ५, १; ५. ४१, २; ७. १५, १; ८६, ७; ८८, १; ९७, २; १०२, १; ८. ४६, १७.
मीळ्हुष्मतीऽइव ५. ५६, ३.
मीळ्हुष्मंतः ६. ५०, १२.
मीळ्हे १. १००, ११; ६. ४६, ४; ९. १०६, १२; १०७, ११.
मुक्षत १०. ८७, १९.
मुक्षीजयाऽइव १. १२५, २.
मुक्षीय ७. ५९, १२.
मुखतः १. १६२, २.
मुखं ६. ७५, १५; १०. ९०, ११; १२.
मुखा ४. ३९, ६.
मुखात् १०. ९०, १३.
मुखे ८. ४३, १०.
मुग्धः ५. ४०, ५.
मुच १. १७७, ४; ३. ३५, ३; ४३, १; ६. ४०, १.
मुचः ४. २२, ७.
मुचत् ८. २४, २७.
मुचध्वं १. १७१, १.
मुचाति २. २८, ३.
मुचाते १०. २७, ११.
मुचीष्ट ७. ५९, ८.
मुच्यते १०. २७, २४.
मुच्यसे १. ३१, ४.
मुंच १०. ९४, १४; १६०, १.
मुंचत ३. ३३, १३; ५३, ११; ४. १२, ६.
मुंचतं ६. ७४, ३.
मुंचतं ५. ७८, ५; ६. ७४, ४.
मुंचते ४. ५३, २; ५. ८१, २.
मुंचथ २. ३४, १५.
मुंचथः १. ११७, ३; ५. ७४, ५.
मुंचंति २. २८, ४.
मुंचंतु १०. ९७, १६.
मुंचंतु १०. ९७, १५.
मुंचस्व १०. ३८, ५.
मुंचामि १०. ८५, २५; १६१, १.
मुंचामि १०. ८५, २४.
मुंजऽनेजनं १. १६१, ८.
मुदः ९. ११३, ११.
मुदा ८. ३९, ७.
मुदीमहि ८. १, १४.
मुदे १. १४५, ४; ५. ५३, ५.
मुद्गलः १०. १०२, ५; ९.
मुद्गलानीं १०. १०२, २.
मुद्गलानी १०. १०२, ६.
मुनयः १०. १३६, २.
मुनिः १०. १३६, ४; ५.
मुनिःऽइव ७. ५६, ८.
मुनीनां ८. १७, १४.
मुमुक्तं ७. ९१, ५; १०. १६१, १.
मुमुक्षमाणाः १०. १११, ९.
मुमुक्ष्वः १. १४०, ४.
मुमुग्धि १०. ७३, ११.
मुमुग्धि १. २४, ९; २५, २१; २. २८, ६; ४. १, ४; ५. २, ७.
मुमुचः ३. ४१, ८.
मुमुच्महे ९. २९, ५.
मुमुत्रे १०. १११, ९.
मुमुरत् ८. ९७, ३.
मुमोक्तु १. २४, १२; १३.
मुमोचत् ७. ८८, ७.
मुमोचत ८. ६७, १४.
मुमोचतं ८. ८६, १.
मुमोचति ८. १८, १२.
मुमोदं १०. ८, २.
मुरः ८. ६६, २.
मुरीय ७. १०४, १५.
मुषाय १. १७५, ४.
मुषायः ४. ३०, ४; ६. ३१, ३.
मुषायत् १. ६१, ७.
मुषायत् ७. १८, १९.
मुषायति १. १३०, ९[2]; ५. ४४, ४; ६. २८, २.
मुषायन् १०. ९९, ५.
मुषिता १०. ६८, १०.
मुषीवाणं १. ४२, ३.
मुषे ५. ३४, ७.
मुष्कऽभारः १०. १०२, ४.
मुष्कयोः १०. ३८, ५.
मुष्टिः ६. ४७, ३०.
मुष्टिऽहत्यया १. ८, २.
मुष्टिऽहा ५. ५८, ४; ६. २६, २.
मुष्टिहाऽइव ८. २०, २०.
मुष्णन् २. २०, ५.

मुहुं ४. २०, ९.
मुहुः २. ४, ५; ५. ५४, ३; ६. २४, ५; ७. २०, २; ८. १, १; २१, ६; १०. १०, ९; २७, २०; ३२, २; १७१, ३.
मुहुःऽगीः १. १२८, ३.
मुहुके ४. १६, १७.
मुहुकैः ४. १७, १२.
मुहूर्तं ३. ३३, ५; ५३, ८.
मुहे ६. १८, ८.
मुह्यंतु १०. ८१, ६.
मूर १०. ९५, १३.
मूरंऽदेवाः ७. १०४, २४.
मूरंऽदेवान् १०. ८७, २; १४.
मूराः ३. ४३, ६; ४. २६, ७; ८. ४५, २३; १०. ४, ४; ४६, ५.
मरासः ८. २१, १५.
मूर्धन् २. ३, २; ६. ४५, ३१; ९. १७, ६; ७१, ४; १०. ८८, ५; १२५, ७.
मूर्धनि १. ३०, १९; ५४, ५; ६. ७, ६; ७. ७०, ३; १०. ४६, ३; १५१, १.
मूर्धा १. ४३, ९; ५९, २; ८. ४४, १६; ७५, ४; ९. २७, ३; १०. ८८, ६; १३२, ४; १५९, २.
मूर्धानः ८. ६७, १३; ९. ६९, ८.
मूर्धानं १. २४, ५; १६४, २८; ३. २, १४; ४. २, ६; ६. ७, १; ९. ९३, ३; १०. ८, ३; ६; ६७, १२; १६६, ५.
मूर्ध्नः ६. १६, १३; ९. ७३, १.
मूलं १०. ८७, १०.
मूषः १. १०५, ८.
मृक्तऽवाहसे ५. १८, २.
मृक्षः ८. ६६, ३.
मृक्षः ४. ३०, १३.
मृक्षत ८. ६७, ९.
मृक्षतं १. ३४, ११; १५७, ४.
मृक्षा ८. ७४, १३.
मृक्षिणीषु १०. ९८, ६.
मृक्षीष्ट १. १४७, ४.
मृगः १. ३८, ५; १४५, ५; १५४, २; १७३, २; १९०, ३; ४. १६, १४; ५. ७५, ४; ६. ७५, ११; ७. ८७, ६; ८. ३३, ८; ९. ३२, ४; ९२, ६; १०. ८६, ३; २२.
मृगण्यवः १०. ४०, ४.
मृगं १. ८०, ७; १०५, ७; २. ३३, ११; ५. २९, ४; ८. १, २०; २, ६; ५, ३६; ६९, १५.
मृगयंते ८. २, ६.
मृगयं ४. १६, १३; १०. ४९, ५.
मृगयसः २. ३८, ७.
मृगयस्य ८. ३, १९.
मृगस्य १. १८२, ७; ५. ३२, ३; ८. ९३, १४; १०. १२३, ४.
मृगाऽइव १०. ४०, ४.
मृगाः २. ३४, १.
मृगाःऽइव १. ६४, ७; ४. ५८, ६.
मृगाणां १. १९०, ४; ९. ९६, ६; १०. १३६, ६; १४६, ६.
मृगाय ५. ३४, २.
मृगासः १. १९१, ४.
मृचा ८. ६७, ९.
मृजंति ९. ६, ५; ८, ४; १५, ८; १७, ७; ६१, ७; ६६, ९; ७२, २; ८६, ४; ९२, ४.
मृजंति ३. ४६, ५; ५. १, ७; ४३, १४; ९. १५, ७; २९, २; ४६, ६; ६३, १७; २०; ६४, २३; ६८, ७; ७२, १; ८५, ७; ८६, २७; ९६, २; १७; ९७, २९; १०७, १७; १०९, १२; २१; १०. १०७, १०.
मृजानः ९. ९६, १०; २०; १०७, २२; १०९, १७.
मृजे ५. ५२, १७[२]; १०. १६७, ४.
मृज्यते ९. ४३, १; ७६, ४; ८६, ६.
मृज्यते ५. १, ८; ९. ३, ३; ६८, ९; ९७, ३; ९९, ७.
मृज्यमानः ९. २०, ६; ३०, २; ३६, ४; ६४, १३; ६५, ६; ७०, ४; ७४, ९; १०७, २१; १०. ६९, ७.
मृज्यमानाः ९. ६४, ५.
मृज्यसे ९. ५६, ३.
मृंजत ९. २४, १; ६५, २६.
मृण १. २९, ५; १३३, ५; ४. १६, १२; ६. ४४, १७; ७. १०४, २२.
मृणन् १०. ८४, ३.
मृणसि १०. ८७, १९.
मृणीहि ४. ४, ५.
मृतं १. ११३, ८.
मृतस्य १. १६४, ३०; १०. १८, ९.
मृतैः १०. १८, ३.
मृतऽमर्यं ७. ८९, १.
मृत्यवः १०. ११७, १.
मृत्यवे १०. ४८, ५; ५९, ४; ६०, ८; ७२, ९; १६५, ४.
मृत्युः १०. १२१, २; १२९, २.
मृत्युऽबंधवः ८. ८१, २२.
मृत्युऽबंधुः १०. ९५, १८.
मृत्युं १०. १३, ४; १८, ४.
मृत्यो इति १०. १८, १.
मृत्योः ७. ५९, १२; १०. १८, २; १६१, २.
मृथाः १०. ९५, १५.
मृधः १. १३१, ६; १३८, २[१]; १८२, ४; २. १८, ४; २२, ३; २३, १३; २८, ७; ३. ४७, २; ५. ३०, ७; ६. ५३, ४; ६०, ५; ७. ४३, ३; ८. ४५, ४०; ६१, १३; ९. ४, ३; ४०, १; ६१, २५; २६; ६३, २४; ८५, २; ८६, २६; ९७, ४३; १०. ६७, ११; ८४, २; ९८, १२; १५२, ३; ४; १८०, २.
मृधाति ६. २३, ९.
मृधि १. १७४, ७.
मृध्याः ३. ५४, २१.
मृध्रऽवाचः १. १७४, २; ५. २९, १०; ७. ६, ३; १०. २३, ५.
मृध्रऽवाचं ५. ३२, ८; ७. १८, १३.
मृध्राणि ८. ४३, २६.
मृध्रेभ्यः ८. ४४, ३०.
मृळ १. ९४, १२; ११४, २; १०; २. ३३, ११; ४. ९, १; ६. ४७, १०; ७. ८९, १; १०. २५, ३.
मृळ १. ३६, १२; ११४, ६; २. २७, १४; ३३, १४; ७. ९३, ७; ८. ४८, ९; ९. ६६, ३०; १०. १६९, १.

मृळतं १. १७१, ४; ५. ५५, ९; ५७, ८; ६. ५०, ११; ५१, ५; ७. ६०, १०; ८. १८, १९; १०. ३४, १४.

मृळत २. २९, ४; ८. ६७, १९.

मृळतं ६. ७४, ४.

मृळतां १०. ९३, ७.

मृळतु १. १७९, ५.

मृळंतु ६. ५०, १२; ७. ५६, १७.

मृळयं ७. ८९, १; ८. ४५, ३१; ४८, ८; १०. ५९, ६.

मृळय १. १२, ९; २५, १९; ६. ४५, १७; ८. ८०, १; ९३, २७; ९. ६१, ५; ८२, २; १०. ३३, ३; १२८, ८.

मृळयंत २. २९, २.

मृळयत्ऽतमः १. ९४, १४.

मृळयत्ऽतमा १. ११४, ९; ५. ७३, ९.

मृळयत्ऽभ्यां १. १३६, १^{२}.

मृळयंतः १. १०७, १.

मृळयंती ५. ४१, १८.

मृळयंतु १. २३, १२; १६९, ५; १७१, ३; ४. ५७, २.

मृळयाकुः २. ३३, ७; ८. ७९, ७.

मृळयाति २. ४१, ११; ७. ८७, ७.

मृळयाति १०. ६६, ३.

मृळयासि ८. ६, २५; ९३, ३०.

मृळात् १०. १०८, ६.

मृळातः १. १७, १.

मृळाति ४. ४३, २; ५७, १; १०. ६४, १.

मृळीकः ६. ३३, ५.

मृळीकं ४. १, ३; ५; ७. ८६, २; १०. १५०, ४.

मृळीकाय १. २५, ३; ५; ६. ५०, १; १०. १५०, १–३; ५.

मृळीके ६. ४८, १२; ८. ४८, १२.

मृश १. १२६, ७; ८. २१, १६; ८१, ६.

मृशते १. १४५, ४.

मृशंति १०. ३४, ४.

मृशसे ९. २०, ३.

मृशस्व ८. ७०, ९.

मृशामसि १०. १७३, ६.

मृषंत ७. १८, २१.

मृषा १. १७९, ३.

मृष्ट १. १४०, २; १७४, ४.

मृष्टः ९. ८२, २.

मृष्टाः १. २२, ४.

मृष्टाः ३. ३३, ८.

मृष्यते १. १४५, २; ६. ५४, ४.

मृष्यंते ६. ६७, १.

मृष्ये ७. २२, ५.

मे १. १०, ९; २३, २०; २४; २५, ४; १६–१९; ५०, १२; ९३, १; १०५, १–१८; ११०, १; ११७, २३; १२२, ४; ६; १२४, १३; १२६, १; ७^{२}; १३१, ६; १३९, ७; ९^{२}; १४५, ३; १४७, २; १६२, ७; १६३, ४; १६४, १६; ३३^{२}; १६५, ४^{२}; १०–१३; १८१, ७; १८३, ५; १८४, २; २. ४, ५; ६, १; १०, २; १४, १०; १८, ८; २४, १५; २७, २; २८, ५; १०; ३०, ७; ३२, १; ३५, १; ३६, ६; ४०, ५; ४१, १३; ३. १५, २; २६, ७^{२}; ३३, ५; ३८, ८; ४३, ५; ५१, २; ५३, ३; १६; ५४, २; १६; २१; ५५, ३; ५७, १; ६२, २; ४. ५, ६; ८; १८, २; १३; २३, ४; २४, १०; ३२, २४; ४१, ८; ९; ५. २, ५; ८; १२, ३; १४, ५; १८, ५; २७, १; २; ४; २९, ३; ३०, २; ३२, ११; ३३, ९; ३६, ३; ४१, १५; १७; ४२, २; ४६, ६; ५२, १२; १६; १७; ५३, ३; ५४, १५; ५६, २; ६१, ९; १०; १७; १८^{२}; ६४, ७; ७४, ६; ७८, ५; ६. ९, ६^{२}; २१, ११; २८, ५; ४७, ३; ४९, ५; ५०, १०; ५२, १३; १६; ६३, २; ९; ६९, ४; ७; ७. १, १०; २०; २५; ७, ६; १८, ४; २२, ३; २३, १; २९, ३; ३३, १; ६२, ५; ६३, ३; ६७, ५; १०; ६८, २; ७६, २; ८२, ८; ८४, ५; ८६, २–४; ८७, ४; ९९, ७^{२}; ८. १, ६^{२}; ३, २१; २२; ४, २१; ५, ३७; ३८; ६, ३२; ७, ९^{२}; ८, १२; १३, २१; १४, १; १९, २६; ३६; ३७; २२, १२; २३, १४; २५, २३; २६, ८; ११; १७; ३२, ६; ३३; ३५, ४; ४३, १६; २७; ४४, २; ४६, २७; ५०, ३; ५४, ४; ५५, ३; ५६, ३; ६१, १०; ६५, १०; १२; ६६, १२; ७३, १०; ८०, ४; ८२, ६; ८५, १; २^{२}; ९; ९१, ५; ९२, २९; ९३, १५; १००, २; ५; १०१, ७; १०२, १९; १०. १०, ११; ११, २; १२, ४; २४, ६; २७, १; ३; ४; १०; १८; २०; २८, २; ४; ६; ३०, ८; ३२, ३; ३४, १३; ३९, ६; ४०, ५; ४३, १; २; ४८, ५; ९; ५१, २; ४; ८; ५२, १; ५४, ५; ६०, १२^{३}; ६१, ४^{२}; ८; १५; १९^{३}; ६२, ७; ६३, २; ६४, २; १२; ६५, १३; ६६, १०; ११; ७०, १०; ७५, ५; ८३, ७; ८६, ५; ७^{३}; १४^{२}; ९३, १२; ९५, ५^{२}; १०; ११^{२}; १७; ९७, २; १४; ९८, १; १०६, ६; १०८, १०; ११९, १; ६; ७; ११; १२२, २; १२८, ४; १४५, २^{२}; ५; १५१, २; १५९, ३^{२}; १६६, २; ५.

मेघः १. १८१, ८.

मेताऽइव ४. ६, २.

मेथामसि १. ४२, १०.

मेथेते इति १. ११३, ३.

मेदः ३. २१, ५.

मेदतां १०. ९३, ११.

मेदनं १०. ६९, २.

मेदयथ ६. २८, ६.

मेदसः ३. २१, १; २; ४.

मेदसा १०. १६, ७.

मेदिनः १०. ३८, २.

मेदी १०. ८४, ६.

मेधंतु २. ३७, ३.

मेधऽअतिथिं ८. ८, २०.

मेधऽपतिं १. ४३, ४.

मेधं १. ३, ९; १६२, १०.

मेधया ४. ३३, १०; ७. १०४, ६; ९. २६, ३.

मेधऽयुं ४. ३८, ३.

मेधऽसातये १. १२९, १; ७. ६६, ८; ८. ३, १८; ४०, २; ६९, १.

मेधऽसाता ४. ३७, ६; ७. ९४, ६; १०. १४७, ३.

मेधऽसातौ ८. ७१, ५.

मेधसातौऽइव ८. १०३, ३; १०. ६४, ६.

मेधस्य ८. १९, २.

मेधा १. ८८, ३; १६५, १४.

मेधाः ३. ५८, २.

मेधाः ८. ५२, ९.

मेधाऽकारं १०. ९१, ८.

मेधाभिः ९. ६५, १६.

मेधां १. १८, ६; २. ३४, ७; ५. २७, ४; ४२, १३; ८. ६, १०; ९. ९, ९; ३२, ६; १०७, २५.

मेधिर १. २५, २०; ३. २१, ४.

मेधिरः १. ३१, २; १०५, १४; १२७, ७[२]; १४२, ११; ३. १, ३; ६. ४२, ३; ८. २९, २; ९. ६८, ४; १०. १००, ६.

मेधिराः १. ११, ७; ८. ३८, ९.

मेधिराणां १०. ८९, १०.

मेधिराय १. ६१, ४; ७. ८७, ४.

मेधिरासः ८. ४३, १९.

मेधे ८. ६, ४४; ५०, १०.

मेधेषु १. ७७, ३.

मेध्यऽअतिथिः १. ३६, १०; ११.

मेध्यऽअतिथिं १. ३६, १७; ८. २, ४०; ४९, ९.

मेध्यऽअतिथे ८. १, ३०; ३३, ४.

मेध्यऽअतिथेः ९. ४३, ३.

मेध्यऽअतिथौ ८. ५१, १.

मेध्याय ५. १, १२.

मेध्ये ८. ५२, २.

मेना १. ५१, १३.

मेनां १. १२१, २; १०. १११, ३.

मेनिं १०. २७, ११.

मेने इति १. ६२, ७; ९५, ६.

मेने इवेति मेनेऽइव २. ३९, २.

मेम्यत् १. १६२, २.

मेळिं ३. २६, ९; ४. ७, ११.

मेषः ८. २, ४०.

मेषं १. ५१, १; ५२, १; ८. ९७, १२; १०. २७, १७.

मेषाऽइव १०. १०६, ५.

मेषाः १०. ९१, १४.

मेषान् १. ११६, १६; ११७, १७; १८.

मेषाय १. ४३, ६.

मेष्यः ९. ८, ५; ८६, ४७; १०७, ११.

मेष्यै १. ४३, ६.

मेहत्न्वा १०. ७५, ६.

मेहना ५. ३८, ३; ३९, १; ८. ४, २१[२]; ६३, १२.

मेहनात् १०. १६३, ५.

मेहनाऽवतः २. २४, १०.

मेहनाऽवान् ३. ४९, ३.

मेहंति ९. ७४, ४.

मैत्रावरुणः ७. ३३, ११.

मो इति १. ३८, ६; ५०, १३; १०५, ३; १३९, ८; १७३, १२; २. १८, ३; ३. ५५, २; ५. ३१, १३; ६५, ६; ७. ३२, १; ५९, ५; ८९, १; ८. २, २०; ५, १३; ९२, ३०; १०३, १३; ९. ११४, ४; १०. १८, १३; २७, २०; ५९, ४; ८.

मोकी २. ३८, ३.

मोघं ७. १०४, १४; १५; १०. ५५, ६; ११७, ६.

मोघं १०. १६५, ४.

मोदते १०. ३०, ५.

मोदते २. ५, ६; ५. ८३, ९; ९. ७१, ३.

मोदध्वं १०. ९७, ३.

मोदमानाः ५. ४७, ६.

मोदमानौ १०. ८५, ४२.

मोदसे १०. ११८, २.

मोदाः ९. ११३, ११.

मोपथ ५. ५४, ६.

मोषीः १. २४, ११; १०४, ८.

मोहयित्वा १०. १६२, ६.

मौजऽवतस्य १०. ३४, १.

मौंजाः १. १९१, ३.

मौनेयेन १०. १३६, ३.

म्यक्ष २. २८, ६.

म्रक्षऽकृत्वा ८. ६१, १०.

म्रद ६. ५३, ३.

म्रियसे १. १६२, २१.

म्लातानि ८. ५५, ३.

य

यंसत् १. ९६, ८; १०७, २; ११४, ५; १८९, ६; १९०, ३; ४; ४. २५, ४; ५; ५४, ६; ५. २, १२[२]; ६. ४९, ७; ७. १०१, २; ८. ४२, २; ९. ९७, ३८; १०. ४२, ८; १२८, ८.

यंसतः ७. ७४, ५; १०. ६६, ७.

यंसते १. ८०, ३; १४३, ७.

यंसन् १. ९०, ३; १३६, ७; ६. ७५, ११; १०. ६६, ५.

यंसि १. ६३, ८; ५. ३६, ४.

यंसि १. ४२, ९; ६१, २; ३. १, २२.

यः १. ४, ४; १०; ७, ९; ८, ७; १२, ८; ९; १८, १; २[३]; २४, ४; २५, ७; ८; १५; ३०, २; ३१, ५; ६; ७; १३; १५; ३३, २; ३५, ६; ३६, ४; १६; ३९, ८; ४०, २; ४; ४२, २; ४३, ५; ४८, ११; ५४, २; ७; ५६, ४; ६३, १; ६७, ४; ५; ६८, ३; ७०, २; ३; ७१, ६; ९; ७३, १–३; ७४, २; ७७, १; २; ७८, ४; ७९, ११; ८१, ६; ८२, ४; ८४, ७; ९; १६; ८६, ५; ९१, १४; २०; ९३, २; ३[२]; ८; १०; ९४, ७; १००, १; १०१, २[४]; ४[४]; ५[३]; ६[४]; १०३, ६; १०५, ७; १६; १०८, १; ११७, २; ११८, १; १२२, ८; ९; १२३, ५; १२५, २; ५; १२६, १; १२७, १; ४; ५; ७; १२९, २[३]; ६; १३१, ७; १३२, ६; १३६, ५[२]; १३८, १; १४०, ६; १४१, ११; १४३, १; ४; ५; १४४, ७; १४७, ४; ५; १४९, २[२]; ३; ५[२]; १५१, ७;

१५४, १^{२}; ३; ४; १५५, ४; १५६,
२^{२}; ५; १५७, ६; १६०, ४^{२};
१६१, १; ४; १२^{२}; १६२, १०;
१६३, ९; १६४, ६; ७; १६^{२}; १८;
२२; ३२^{२}; ३९; ४९^{४}; १६७, ७;
१७३, ५^{२}; १७६, २–४; १८१, ३;
१८२, ३; १८३, १^{२}; ३; १९०,
२; ३; **२.** १, ७; ९; ४, १; ३–७;
८, २–४; १२, १; २^{४}; ३^{३}; ४^{२};
६^{४}; ७^{२}; ९^{२}; १०^{२}; ११^{२}; १२^{२};
१३^{२}; १४^{४}; १५; १३, २–६; ७^{२};
८; १४, २; ३^{२}; ४^{२}; ५^{५}; ६^{२}; ७;
११^{२}; १७, २^{२}; ४; १९, ४; २०,
२; ३^{२}; २३, ४; ६; ७; १२; २४,
१; २; ११; १४; २६, ३; ४;
२७, १२; १३; २८, १; १०^{२};
३०, २; ७^{४}; ९; ३३, ५; ७; ३४,
९; ३५, ८; ३६, १; ३७, २; **३.** १,
१२; १०, ३; १३, ३; १६, ४; १७,
५; २३, ३; ३२, ८; १३^{२}; ३४,
८; ३६, १; ३७, ११; ४२, १;
४९, २; ५१, ११; ५३, १२; २१;
५९, २; ७; ६२, ९; १०; **४.** २,
१; ६; ७; ८^{२}; ९; ४, ३^{२}; ४; ६;
७^{२}; १०^{२}; ५, २; ४; ७, ४; ९,
१, १२, १; २; १५, ४; १६, ५;
१६^{२}; १७, ४; ५; ८; ९; ११; १२^{२};
२०, ५; ६; २१, ४^{२}; ५; ६; २२, १;
३; २४, ६; ७; २५, ४; २९, २;
४; ३०, २२; ३५, ६; ३८, ४; ३९,
३; ४१, १; २; ४; ४४, १; ४५,
७; ५०, १; ७; ९; ५३, ६; ५४,
१; ५६, ३; ५८, ११; **५.** १, ७;
३, ७^{२}; ९; ४, १०; ६, १; २; ७,
९; ९, ४; १२, ६; १३, ३; १७,
३; १८, १; २२, १; २३, १; २५,
६; २७, २–४; ३०, १; १५; ३२,
३; ३३, १; ३४, २; ३^{३}; ७; ३५,
१; ३६, १; ६; ३७, १; ३; ५;
४२, ७; १०^{२}; ११^{२}; १३; १४;
४४, ८; १४^{३}; ४६, ८; ५१, १२;
५४, १३; ५८, ३; ६१, १०; ६५,
१; ७७, ४; ८१, ३; ८२, ९; ८५,
१; ५; **६.** १, ९^{२}; ११; २, ४; ५;

३, ५; ६^{३}; ७; ८^{२}; ४, २; ३; ५^{२};
५, १; ४^{२}; ५^{२}; ६, २; ७, ७^{२}; ९,
३; १०, ३; ४; १२, ५; १३, ४;
१४, १; १५, ५^{२}; ११; १३; १६,
२३; ३१; ३२; ३९; ४६; १७,
१, २^{५}; १८, ८; १०; १९, २; ७;
२०, १; २१, २; ४; २२, १^{२}; ३;
२३, ५; ३३, १^{२}; ३४, २; ३६,
५; ४१, ३; ४४, १^{२}; २; १३;
४५, १; ११^{२}; १७; ४६, ३; ४७,
२; ४; ४८, ५; ६; ४९, ५; १३;
५०, ८; ५१, २; ५२, २^{२}; ८;
५४, १^{२}; २; ४; ५५, ४; ५६, १;
५९, ४; ६०, १; १०, ११; ६१,
५; ६२, ९; ६३, १; ४; ६८, १;
५; ६; ९; ७०, ३; ७१, २^{२}; ७३,
१; २; ७५, १९; **७.** १, २; ८;
१५; २३; ३, १; ९; ४, १–३;
५; ५, १; ६, ४; ५^{२}; ७, ४; ८,
४; ९, २; ४; १२, १; १५, १; २;
१६, ६; १८, ७; ११; १८; १९,
१^{२}; २०, ५; ६^{२}; ८; २२, २; २३,
१; २७, २; २८, ५; ३२, ५; ६;
१२; १३; ३६, ४^{२}; ३८, १; ४१,
२; ५५, ६^{३}; ७; ५६, १८; २४;
५८, १; ५९, २; ८; ६०, ३; ११;
६१, १; ६३, १; ३; ६४, ४; ६७,
१; ६८, ५; ७; ६९, ५; ७०, २;
६; ७३, २; ८२, १; ८४, ४; ८५,
४; ८६, १; ८७, ७; ८८, १; ६;
९०, २; ९६, ६; ९७, २–४; १००,
१^{२}; १०१, २^{३}; १०२, २; १०४,
७; ८; १०^{४}; ११^{२}; १५; १६^{२}; **८.**
१, ८; १२; २७; ३१; ३२; २,
२४; ३४; ३७; ३९; ४, ६; ५,
१९; ३४; ३८; ६, १; १६; १७;
८, १५; १६; १९; १२, १; ६; १३,
८; ९; १७, १३; १८, १३; १४;
१९, ५^{४}; १३; १४; २२; २४;
२०, १५; २१, २; ९; १०;
२२, ५; २३, १०; १५; २१; २४,
३; १९; २७^{२}; २५, २; १८; २६,
१३; १४; २७, ८; १५; ३१, १;
२; १५; ३२, २; ११; १८; २०^{२};

२५^{२}; २८; ३३, ४^{२}; ५^{२}; ६^{२}; ७;
९; १६; ३९, ८; ४०, १०; ४१,
१; २; ४; ५^{२}; ७; १०^{२}; ४४, १५;
४५, ५; ६; १५; ३०; ४६, ८^{४};
९; १२; २१; २९–२८; ४८, १०^{२};
१२; ४९, १; ५०, १; ५१, ३^{२};
५; ८; ५२, ३^{२}; ५३, २; ७; ५८,
१; ५९, ३; ६०, ७; ६६, २; ३^{२};
४; ६८, ७; ६९, १३^{२}; ७०, १^{२};
३; ७; ८^{२}; १३; ७१, ११; १३;
७३, १३; ७४, ३; ८०, २; ८१,
८; ८२, ७; ८; ८४, ९; ९१,
२; ९२, १६; १७^{३}; १८; २३; ९३,
२; ३२; ९५, ४; ५; ९६, ६; १९^{२};
९७, ३; १००, ७; १०१, १; ३;
४; १०२, ११; १०३, ४; ६; ११;
१२; **९.** ७, ७; १२, ४; ५; १४,
५; १८, ४–६; २१, ५; २४, ४;
३८, ५; ३९, ४; ४३, १; ५२,
३; ४; ५३, ३; ५५, ४; ६१, १;
१४; १९; २२; ६३, ११; १६;
६४, ११; १२; ६६, १७; ६७,
२२; ३१; ३२; ६८, ३; ८; ७४,
२; ३^{२}; ७६, ४; ७७, ४; ७८, ५;
७९, ४; ८४, २; ३; ८६, १५;
८८, ३–५; ८; ९१, २; ९६, १८;
९७, ४६; ४८; ९८, ३; ७; ९९,
३; १०१, २; ९^{२}; १५; १०७, १^{२};
१०८, ६; ८; १३^{४}; ११४, १^{२}; २;
१०. ३, ५; ६; ६, १; २^{२}; ३; ८,
३; ९, २; १०, १२; ११, ७; १२,
६; १४, ५; १६, ५; ६; ८; १०;
११; १७, ११; १२^{३}; १३^{३}; १८,
१; १९, ४; ५^{२}; २२, १–३; २३,
५^{२}; २४, ३; २६, ५; ७; २७, १;
३; ७; १०; ११^{२}; २१; २८, २;
२९, १; २; ३०, ४; ७^{३}; ८; ९;
३४, १२; ३५, १४; ३७, १२;
३८, ३; ४^{३}; ३९, १; ४२, ४–७;
९; ४३, ८; ४४, १; ४५, ९; ४६,
१; ४७, ६; ४९, ३; ६; ५१, २;
५२, ३; ५४, ६^{२}; ५५, ६; ५७,
२; ५९, १०; ६०, ३; ६१, ३;
६२, ८; ६३, ६; ६५, १०; ६८,

१२; ७१, ६; ७२, १; ७४, ५; ७९, ५; ८०, ४; ८१, १; ८२, ३^{२}; ७; ८३, १; ८५, ३४; ३९: ८६, २१; ८७, ८^{२}; ११; १६^{३}; ८८, ३; ४; ७; १२; १४; ८९, १; ३; ४; ९३, २; ९६, १; ३; ४; ७; ८^{२}; ९७, २३; ९९, ९; १०; १००, २; १०५, ५; ७; १०७, ५–७; ११०, ९; १११, ४; ११२, २; ११५, १; २; ६; ११६, ३; ११७, २–४; १२१, २; ३^{२}; ५; ८^{२}; ९^{३}; १२२, ३; १२५, ४^{३}; १२८, ७; १२९, ७; १३०, १; १३३, ३; ४; ५^{२}; १३६, ५; १४४, ४; १४७, ४; १४८, ५; १५२, ४; १६०, ३; ४; १६२, ३^{३}; ४^{२}; ६^{२}; १६४, ५; १७०, १; १७४, २; १७८, ३; १८७, २–५.

यक्के ८. २१, १८.

यक्नः १०. १६३, ३.

यक्षत् ६. १२, २; ७. १७, ४; ८. ३९, ९; १०. १६, ११.

यक्षत् १. १३९, १०; ३. ४, ३; १९, १; ५. १३, ३; ६. १५, १०; ४९, ९; ६२, ४; ९. ७४, २.

यक्षतः २. ३, ७.

यक्षतां १. १३, ८; १४२, ८; १८८, ७.

यक्षते ८. १९, ४.

यक्षऽदृशः ७. ५६, १६.

यक्षंत १. १३२, ५.

यक्षऽभृत् १. १९०, ४.

यक्षं ४. ३, १३; ५. ७०, ४; ७. ६१, ५.

यक्षंवः ७. १८, १९.

यक्षस्यं १०. ८८, १३.

यक्षि १. १३, १; १४, १; ३१, १७; ३६, ६; ७५, ५; २. ६, ८; ३६, ४; ५. २६, १; ६. १६, ९; २४; ४८, ४; ७. ९, ५; ६; १६, ५; १७, ३.

यक्षि १. १०५, १३; १४२, ११; २. ३, ३; ३. ४, १; १४, ५; १७, २; ३; ५३, २; ५. २८, ५; ६. ४, १; १६, ८; ७. ११, ३; ३९, ४; १०. १, ६; ४, १; ५२, ५; ७०, ४; ९; ११०, ३; ९.

यक्षिन् ७. ८८, ६.

यक्षुः ७. १८, ६.

यक्ष्म १०. ९७, १३.

यक्ष्मं १. १२२, ९; १०. ९७, १२; १३७, ४; १६३, १–५.

यक्ष्मंस्य १०. ९७, ११.

यक्ष्माः १०. ८५, ३१.

यक्ष्यंः ८. ६०, ३.

यक्ष्यमाणं १. १२५, ४.

यक्ष्यमाणान् १. ११३, ९.

यक्ष्वं १. ४५, १०; ५. ४२, ११.

यक्ष्व ४. १, ५.

यच्छं १. २२, १५; ४. १२, ५; ५. २७, २; ७. १६, ८; ३०, ४.

यच्छ १. ५८, ८; १०२, ३; ११४, १०; ३. ५१, ११; ५. ८३, ५; ६. १५, ३; १६, ३३; ४६, ९; १२; ७. ५, ९; १०. ९८, ११; १०२, ३; १४१, १; १५२, ४; ५; १६९, २.

यच्छंत २. २७, ६.

यच्छत १. ८५, १२; ४. ५१, १०; ५. ४६, ७; ७. ५९, १; ८. १८, १२; २७, ९; ३०, ४; ४७, २; १०. १५, ७; ३५, १२; ३७, ११; ६३, ७; १२.

यच्छंतं ८. ८, १६.

यच्छतं १. १७, ८; २१, ६; ४६, १५; ९२, १६; ९३, ८; ४. ४७, ४; ५०, १०; ६. ५९, ९; ७. ७४, २; ८२, १; ८; ८३, ९; ८. ९, १; १५; ३५, २१; २२.

यच्छतात् १. ४८, १५.

यच्छतां २. ४१, २०.

यच्छंति ४. ५३, १.

यच्छति ५. ८०, २; ९. ८६, १५.

यच्छतु ३. १३, ४; ४. ३२, १५; ५३, ६; ५७, ७; ६. ७५, १२; १७^{२}; ८. ३४, २; ४७, ९; १०. १९, २; ६६, ३; १०३, १३; १४१, २.

यच्छध्वं ७. ४३, २.

यच्छंति ७. ६०, ८; १०. १०७, ४; १८५, ३.

यच्छंति ६. ७५, ६; ७. ७९, २; ८. ४, २.

यच्छंतीः ७. ७८, ३.

यच्छंतु ३. ५४, २०; ७. ३९, ७.

यच्छंतु १. १३०, २; ७. ८२, १०; ८. १८, ३; ३२, २३; १०. १२६, ७.

यच्छमानाः ७. ५६, १३.

यच्छंसे १. ८४, ६; ७. ५५, २.

यजं १. ४५, १; ७५, ५^{२}; ७६, २.

यज १. १४, ११; १५, १२; २६, १; १८८, ९; ३. १७, ५; २५, १; ६. १६, २; ४७, २७; ५२, १२; ७. ४२, ५; १०. २, १.

यजत ४. १, १.

यजतः १. ३५, ३; ४; ५९, ७; १४१, ७; १८१, ३; २. १४, १०; ३. ५, ३; ५. ४१, ९; ४४, १२; ६. ५०, ८; ७१, ४; ८. १७, १५; ९. ६९, ३; ८६, १४; १०. ९२, १; ९९, ११.

यजतं १. १२८, ८; १५१, १; २. ३३, १०; ५. ८, १; ४६, ५; ६७, १; ६. १, ८; ४९, ९; ५८, १; ७. २, १; ९७, ५; १०. ७, ३.

यजतस्यं ५. ४४, १०; ११; ७. २, २.

यजता १. ३४, ७; ४. १५, ८; ५. ४३, ११; ६४, ७; ७. ७५, ७; १०. ११, ८; ४०, ३.

यजताः ६. ५०, २.

यजतां १०. १०१, ९.

यजतां ६. १५, १३.

यजताय २. १६, ४; २१, १.

यजंति १. २६, ३; १२०, ५; १३३, ७; १५१, ७; ७. ७, ५.

यजति १. १३९, १०.

यजतु २. ३, १; १०. २, २; ११, १.

यजंते १. ३१, १५; १८०, ३; ४. ६, ११; ६. २८, ३; ७. ७३, २; ९. ७१, ३.

यजते ५. ७७, २.

यजते इति ४. ५६, २; ४; १०. ११०, ६.

यजतेभिः ५. १, ११.
यजतेभ्यः २. ५, ८.
यजत्र १. ७६, ४; १८९, ३; ७; ३. १४, २; २२, २; ३५, १०; ६. १२, २; २५, ८; ७. १४, २; १०. ११, ८.
यजत्रः १. १२१, १; १७३, २; ७. ५२, ३; १०. ३१, १.
यजत्रं १. १२९, ७; ७. ८८, १; १०. ४६, ९; १०; १४९, ३.
यजत्रा १. १०८, ७; १८०, ५; ८. ५७, १; ४.
यजत्राः १. १४, ८; ६५, १; ३. ६, ८; ५७, ४; ६. ५२, १३; ७. ३५, १५; ४३, ४; १०. ७०, ११.
यजत्राः १. ८९, ८; १८६, ११; २. २७, १६; २९, ६[२]; ३१, ७; ४. १२, ६; ५. ५५, १०; ५८, ४; ६. ५०, १५; ५१, ६; ९; ५२, १७; ७. ५७, १; ४; ५; १०. ६१, २७; ६३, ११.
यजत्रान् १. १४, ७; ३. ५७, ५.
यजत्रे इति ३. ३१, १७; ७. ५३, १.
यजत्रैः ४. ५६, २; ६. २१, ११; ७. ७५, ७.
यजथः १०. १०६, ३.
यजथाय २. २८, १; ३. ४, १; ५, ९; १७, १; १९, ५; ५. १, २; ११, २; ७. १०, ५; १०. ७, १; १२, १.
यजध्यै ३. १, १; ४, ३; ४. २१, ५; २४, ५; ६. ११, ३; १२, १; २; १५, १५; ४९, २; ६८, १; ७. २, ७; १०. ६१, १५; ११०, ७.
यजध्यै ८. ३९, १.
यजध्व ८. २, ३७.
यजध्वं २. २, १; ३, ३; ५. ७७, १; २; ६. २९, १; १०. ३०, ३.
यजन्ता १०. १२८, ३.
यजन्ति १. ९१, १९; ५. ४५, ४.
यजन्तु १०. १२८, ४.
यजन्ते ७. ३६, ५.
यजन्ते ४. २४, ५.
यजन्तौ २. ३, ७.
यजमान ८. ३१, १६.
यजमानः १. २४, ११; ३. १, १५; ३, ३; ४. १७, १५; ५. ७७, २; ६. ५१, १२; ८. ३१, १५.
यजमानं १. १३०, ८; १५६, ५; ५. ४५, ५; १०. १२८, ७.
यजमानस्य १. ५१, ८; १७८, ४; २. २०, ७; ३०, ६; ३. ५३, ३; ५. ४४, १३; ६. ५४, ६; ६०, १५; ७. ५७, २; ८. १२, १८; ५८, १; १०. ४०, १४; ४९, १; ११६, ८.
यजमानाः १. १२७, २; १०. ४५, ११; १५१, ४.
यजमानात् ४. १०, ७.
यजमानाय १. ८१, २; ८३, ३; ९२, ३; ९३, ७; ३. १७, ३; ५. २६, ५; ६०, ७; ६. १५, १६; ७. १६, ६; ८. १४, ३; १७, १०; ५९, १; ४; १०. २७, १; १००, ३; १२२, ६; १२५, २; १७५, ४; १८२, १.
यजमानासः २. १८, ३; १०. १६०, १.
यजमाने ३. २९, ८; ८. ९७, २.
यजमानेषु ८. ५९, ७; १०. १७, ९.
यजसा ८. ४०, ४.
यजसि ६. ४८, ४; १०. ९१, ११.
यजसि १०. ११०, १.
यजसे ८. २५, १.
यजस्व २. ९, ४; २६, २; ६. ११, १; २; ४; ७. ४२, ३; ८. २३, १.
यजस्व १. ७६, ५; २. १६, ४; ३. १, २२; ८. ११, १०; १०. २, ६; ७, ६; ८१, ५; ६; ९८, ४.
यजात् १०. २, ३.
यजाति ८. ३१, १.
यजाति १. ७७, २; ३. ४, १०; ७. ३९, १; १०. २, ५; ९५, १८.
यजाते ७. १००, १; ८. ३१, १.
यजाते ३. ५३, ११; ६. ४७, १५.
यजाते १. ८४, १८.
यजाम १. २७, १३; ५. ६०, ४.
यजाम १०. १२४, ६.
यजामः ३. ३२, ७.
यजामसि १०. १७२, ३.
यजामसि १०. १३२, २.
यजामहे १. १५, १०; २६, ६; १५३, १; १०. २३, १.
यजामहे १. ४०, ४; ८३, ५; ९७, २; ७. ५९, १२; ८. ४०, २.
यजामहै १०. ५३, २.
यजासि ३. १९, ४; ६. ४, १.
यजासि ३. २९, ८; ६. १५, १४.
यजिष्ठ २. ६, ६.
यजिष्ठः १. ७७, १; १२८, १; १४९, ४; ३. १०, ७; १३, १; ४. १, ४; २, १; ७, १; ६. १५, १३; ७. १५, ६; ८. ६०, ३; १०. २, ५; ६, ४.
यजिष्ठं १. ३६, १०; ४४, ५; ५८, ७; १२७, २; ४. १, १९; ७, ५; ८, १; ५. १४, २; ७. ३, १; ८. १९, ३; २१; ६०, १; १०. ४६, ८; ११८, ९.
यजिष्ठेन ३. १४, ५.
यजीयान् २. ९, ४; ३. ४, ३; १७, ५; १९, १; ४. ६, १; ५. १, ५; ६; ६. १, २; ६; ११, १; १०. १२, २; ५२, २; ५३, २; ११०, ३; ९.
यजुः ८. ४१, ८; १०. १२, ३; ९०, ९; १०६, ३; १८१, ३.
यजुषा ५. ६२, ५.
यजे २. ९, ३.
यजेत ७. ६०, ९.
यजेथां १०. ७०, ७.
यज्ञः १. १८, ७; १०७, १; १५६, १; १६४, ३५; १७३, ११; १७७, ४; १८१, १; १८८, २; ३. १२, २; ३२, १२[२]; ४. २, ५; ३४, ३; ५८, ९; ५. २२, २; ६. ११, ५; २१, ४; ३८, ४; ४०, ४; ६८, १; ७. ७, ३; १६, २; ३४, १७; ४३, २; ७०, ६; ८. ६, २२; १३, ३२; १४, ५; १८, १९; ६८, ११;

८९, ६; **९.** १०, ३; ८८, ७; **१०.** १४, १३; २०, ६; ५०, ६; ५१, ९; ६६, ६; ७७, ४; ८८, ८; ९३, ८; १००, ५; ६; १०३, ८; १०४, ६; १०५, ८; १३०, १.

यज्ञऽकामः **१०.** ५१, ५.

यज्ञऽकेतुः **४.** ५१, ११.

यज्ञऽधीराः **७.** ८७, ३.

यज्ञनिःऽकृतः **१०.** ६६, ८.

यज्ञऽनीः **१.** १५, १२.

यज्ञऽन्यं **१०.** १०७, ६.

यज्ञऽन्योः **१०.** ८८, १७.

यज्ञऽपतौ **१०.** १७०, १.

यज्ञऽप्रिये **१०.** १२२, ६.

यज्ञऽबंधुः **४.** १, ९.

यज्ञं **१.** १, ४; ३, १०; ११; १०, ४; १२, १०; १३, २; ८; १२; १५, २; ३; ६; २०, २; २२, ३; १३; २६, १०; ३४, ३; ९; ४०, ३; ४१, ५; ४७, ४; ८४, २; ९१, १०; १९; १०५, ४; १२२, १; १३९, ११; १४२, २; ३; ८; १६२, ४; १६४, ५०; १७०, ४; १८८, ७; **२.** १, १०; २, ११; ५, ७; ८; ३४, १२; ३६, ६; ४१, २०; **३.** १, २; २२; ३, ६; ४, २; ५; ८, ८; ११, १; १७, २; १९, २; २१, १; २२, ४; २५, ४; २६, ६; २९, ८; ३२, १२; ३५, २; १०; ४०, ३; ४३, ३; **४.** ९, ७; १४, १; २०, २; ३; २३, १; २९, २; ३३, ३; ३४, १; ६; ३७, १; ३९, ५; ४४, ४; ५६, ७; ५८, १०; **५.** ४, ५; ५, २; ५; ७; ११, ४; १२, ६; १३, ४; ४१, ७; ४३, १०; ११; ५२, ४; ५; १०; ७२, ३; ७७, १; ७८, ३; ८७, ९; **६.** १०, ६; १५, १६; १८; १६, २२; ४०, ५; ४१, १; ४; ४४, १५; ६२, २; ६९, १; ७०, ५; **७.** १, १२; १०, २; ११, ५; २१, २; ३४, ५; ६; ४२, ३; ४४, २; ५१, १; ५९, ११; ६१, ६; ६६, ११; ७३, ३; ७८, ३; ८०, २; ८४, ३; **८.** १०, २; ११, ४; १३, ११; १८; ३०; १४, १२; २०, २; २६, १५; ३५, ४; ३८, ४; ४४, ८; ४६, १८; ४९, ७; ५७, २; ५८, १; ५९, ६; ६६, ५; ७५, ५; ८७, ३; १०१, ९; **९.** ५, ८; १०१, ३; १०२, ७; १०७, ६; **१०.** १३, ४; १५, ६; १३; १७, ९; ३५, ११; ३६, ६; ४१, २; ४६, ४; ५२, ४; ६१, ४; ६३, ५; ६५, ७; ६६, २; १२; ७०, ८; ७३, ४; ७४, ३; ८७, ९; ८८, १७; १९; ९०, ६; ७; १५; १६; ९६, १२; ९८, ९; १०१, २; १०४, १; ११०, २; ७; ८; ११; ११४, ६; १२१, ८; १२२, ६; १२४, १; १२८, ७; १३०, ६; १४१, ६; १५७, २; १६७, २; १८८, ३.

यज्ञऽमन्मा **७.** ६१, ४.

यज्ञंऽयज्ञं **३.** ६, १०.

यज्ञऽयते **५.** ४१, १.

यज्ञऽवनसः **१०.** ५०, ५.

यज्ञऽवनसं **४.** १, २^{२}.

यज्ञऽवतः **३.** २७, ६.

यज्ञऽवाहसः **१.** ८६, २.

यज्ञऽवाहसं **९.** १२, २०.

यज्ञऽवाहसा **१.** १५, ११; **४.** ४७, ४.

यज्ञऽवाहसे **३.** ८, ३; २४, १.

यज्ञऽवृद्धं **६.** २१, २.

यज्ञऽश्रियं **१.** ४, ७.

यज्ञऽसहं **१०.** २०, ७.

यज्ञऽसाधनः **१.** १४५, ३; **९.** ७२, ४.

यज्ञऽसाधं **१.** ९६, ३; ११४, ४; १२८, २.

यज्ञस्य **१.** १, १; १२, १; ४४, ११; ९६, ६; ११३, १९; १२७, ६; १२८, ४^{२}; **२.** ३, २; ६; ५, २; ४१, १९; **३.** ११, ३; १२, ३; १५, ४; २१, ३; २७, २; ५; ८; २९, ५; **४.** ५६, २; **५.** ११, २; १५, २; **६.** २, ३; ७, २; १५, ११; ४९, २; ६५, २; **७.** १५, ५; **८.** ६, ३; १०, ४; १२, ११; ३२; १३, २९; १९, ३; २३, ९; ३८, १; ७२, १२; ८४, ५; **९.** २, १०; ६, ८; १७, ६; ८६, ७; १०; १०२, २; **१०.** २, ५; ८, ६; ५३, १; ३; ५७, २; ६७, २; ७१, ११; ९२, १; १०५, ९; १८१, २.

यज्ञस्यऽयज्ञस्य **१०.** १, ५.

यज्ञऽहोतः **८.** ९, १७.

यज्ञाः **४.** ३७, २; **७.** ३५, ७; **८.** १०, ४; **१०.** ७७, १.

यज्ञात् **१०.** ५७, १; ९०, ८.

यज्ञान् **३.** ९, ६.

यज्ञानां **१.** ४४, ३; ७६, ३; **३.** २, ५; ३, ३; ४; १३, ३; **६.** ७, २; १६, १; **८.** ४४, १०; २७; **१०.** २६, ५.

यज्ञाय **१.** ९३, ६; ९४, ९; १११, २; **३.** ३०, १५; ३९, ८; **६.** ४०, १; **७.** ९९, ४; **८.** १२, १९; **१०.** २१, १; १७६, ३.

यज्ञाऽयज्ञा **१.** १६८, १; **६.** ४८, १.

यज्ञासः ५. ९, २; **६.** २३, ८; **८.** २३, १०; ७१, १०.

यज्ञियः **१.** १४२, ३; **३.** ३२, १२; **४.** १५, १; **५.** १०, २; **८.** २३, १८; ३९, ७; ७५, ३; ९७, १३; १०३, ११; **९.** ७१, ६; ७७, ५; **१०.** ११, १; ५०, ४; ८८, ५.

यज्ञियं **१.** ६, ४; २०, ८; ११९, १; १६१, ६; **२.** २३, २; **३.** २, १३; ६०, १; ७; **६.** १६, ४; ४८, २१; **८.** ८०, ९; ९६, ४; **१०.** १२४, ३.

यज्ञियस्य **३.** १, २१; ३२, ७.

यज्ञिया **८.** २५, १; **१०.** ६६, ९.

यज्ञियाः **१.** १४२, ९; **२.** ४१, २१; **५.** ५२, १; **६.** ५२, १४; **७.** ३५, १५; **१०.** १९, ७; ३६, १०; ६६, ६; ८५, ३१; ९३, ३.

यज्ञियाः ५. ८७, ९.

यज्ञियान् **१.** १८८, ३; **१०.** ११, १; ५३, २.

यज्ञियानां ३. ३३, ११; ४. १, २०; ४३, १; ५. ४२, ४; ६. ४१, १; ६३, ५; ७. ३५, १५; ३९, ६; ८. ९६, ४; १०. १४, ६; ८८, ६; १२५, ३.

यज्ञियानि १. ७२, ३; ८७, ५; १०. ६३, २.

यज्ञियां ७. ४२, ३; १०. ४४, ६; १०१, ९[२].

यज्ञियाय १. २७, १०; ५. १२, १.

यज्ञियासः १. ७२, ४; ६; ७३, ७; १४८, ३; १६१, २; २. ३, ४; ३. ६, ३; ५४, १३; १८; ६. ५, २; ७. ३५, १४; ३९, ४; ८. ९६, ८; १०. ८८, ११; १३.

यज्ञियासः १. ७२, ६; ५. ६१, १६; ६. ४९, ११; ८. ३०, २; १०. १८, २; ५३, ४.

यज्ञियासु ७. ९५, ३; ८. ३९, ७; १०. १३२, ५.

यज्ञिये इति ७. २, ६; १०. ६४, १४.

यज्ञियेन ७. ६७, १.

यज्ञियेभिः १०. १४, ५; ८८, ३.

यज्ञियेभ्यः १. १३९, ७[२]; ४. ५४, २; ५. ५२, ५.

यज्ञियेषु ७. ३२, १३.

यज्ञे १. १३, ३; ७; १०१, ९; १०९, ५; १३२, १; ३; १४२, ५; १८५, ७; ३. २९, १६; ३५, ६; ४. १४, ४; ३४, ११; ५०, १०; ५८, २; ५. १२, १; ७५, ८; ६. १०, १; ७. ६९, ५; ९५, ४; ९७, १; ८. ४४, १३; ४९, ७; ७६, ७; १०. १४, ५; २०, ५; ७०, ७; ७७, ७; १३०, ६.

यज्ञेन १. १६२, ५; १६४, ५०; २. २, १; २१, ५; ३. ३२, १२; १३; ५. ३, ५; ६. ५, ५; ६, १; ५२, १; १०. ६२, १; ७१, ३; ९०, १६.

यज्ञेभिः १. २४, १४; १६६, १४; ५. ६, १०; ६. २, २; ३, २; ४, १; ८. १९, २०; २३, ८; २४, १८; २६, १३; ४६, १७; ६८, १०; १०. २४, २.

यज्ञेऽयज्ञे १. १३६, १; ५. ५, ९; ८. ५९, १; १०. ९३, २.

यज्ञेषु १. १४, ११; १५, ७; २१, २; ४४, १०; १२८, ७[२]; ३. २, ६; १०, २; २४, ४; ५. २०, ३; २१, ३; ६. १४, २; १६, ३; ४; ७; ७. २, ७; ३७, २; ३९, ४; ४३, १; ५७, १; ६०, १२; ८. ३, ४; ११, १; २३, २२; ३९, ८; ६०, २; १०२, १०; ९. १७, ४; ४९, ३; ९८, ९; १०. २१, ४; ६; ९३, ३.

यज्ञैः १. ७६, १; ८३, ५; ८६, २; १३१, २; १५१, ७; ८; १५९, १; १७३, १०; २. ३५, १२; ३६, २; ३. ३१, ३; ३२, ५; ६२, १२; ४. ५०, ६; ५. १७, १; ७४, ७; ६. १२, ४; १३, ४; १८, १५; २०, १०; २३, ६; २४, ६; ३४, २; ४; ७. २, २; २०, ६; २१, १; ८. ७०, ३; ९. ४, ९; १०४, १; १०५, १; १०. ७४, १; ७८, १; ८७, ४.

यज्यवः ३. १९, ४; ८. ६३, ५.

यज्यवः २. १४, ८.

यज्यवे १. ३१, १३; ५५, ६; ५. ४१, ३; ९. ६१, १२; ८६, २६.

यज्यू इति १०. ६१, १५.

यज्यून् ५. ३१, १३.

यज्योः ४. २३, २.

यज्वनः १. १३, १२; ६. २८, ४; ८. ३२, १८.

यज्वने ६. २८, २.

यज्वऽभिः १. ३३, ५; १०. ९६, ५.

यज्वरीः १. ३, १; १०. ४१, २.

यज्वऽसु १०. १५१, २; ३.

यज्वा २. २६, १; ३. १४, १; ६. १५, १४.

यत् १. १, ६; १०, २; १२, ४; १५, १०; २२, २१; २३, ११; २२; २५, १; २६, ६; २८, ५; २९, १; ३०, ३; १५; ३१, ४; ११; १४; १८; ३२, ४; ११–१४; ३३, ५; ९; ३६, १३; ३७, ३; ५; ६; ९; १२; १३; ३८, ४; ८; ९; ३९, १; ३; ४४, १२; ४६, ३; ४७, ७; ४८, १०; १५; ५०, ५; ५१, ४; १०; ११; ५२, २; ५; ६; ९–११; १५; ५३, ६; ७; ५४, ४; ५; ५५, ४; ५६, ५; ५७, २; ५८, १; ४; ६१, ११; १३; १५; ६२, ६; ६३, १; २; ४; ७; ६४, ७; ६५, ४; ६६, ३; ६७, २; ६८, १; २; ६९, ३[२]; ७१, ४; ५; ८; ७२, ३; ६; १०; ७४, ७; ७७, २; ७९, ३; ८०, ७; ११; १३; १४; ८१, ३; ८३, ६; ८४, ६; १४; ८५, ३–५; ७; ९; ८६, १०; ८७, २; ३; ५; ८८, ५; ८९, ८; ९३, ४; ९४, ५; १०; ११; १४; ९५, ८; ९७, ३–५; १००, ११; १०१, ८, १०२, १; १०३, ४; ७; १०४, ५; १०६, ५; १०८, ६–१२; ११०, २; ३; ११२, २१; ११३, ९[२]; १०; २०; ११४, २; ११६, ५; ११; १२[२]; १८; ११७, ८; १०; १६; २२; ११९, ३; १२०, ७; १२१, १; ४; ५[२]; ७[२]; ८; १०[२]; १२२, ९; ११; १३; १२३, ३; १२७, ३; ७; १०; १२८, ५; १३०, ९; १३१, ३; ४; ५[२]; ६; १३२, ४–६; १३४, २; १३६, ४[२]; १३८, २; १३९, १; २; ७; ८[२]; १४०, ५; ११; १४१, १; ३[२]; ४[२]; ५–७; ९; १४४, २; १४५, २; ४[२]; १४६, ५; १४७, १; १४८, १; १५१, २; ३[२]; १५३, १–३; १५७, २; १५८, १[२]; २–४; ५[२]; १६०, २; १६१, १; ३; ५; ११; १२; १६२, १–४; ८[२]; ९[४]; १०; ११; १३; १४[२]; १६; १७; १६३, १; १०; १३; १६४, ४; २३[२]; १६५, ३; ६; ७; ११; १४; १६६, ५; १३; १४; १६७, २; ५–७; १६८, ६; ८; १६९, ६; १७०, १; १७३, १; २; ६; ८; १७४, २; ४; ९; १७८, १; १७९, ३[२]; ५; १८०, १; २[२]; ३; ६; ९; १८१, १; ९; १८२, ८; १८३, २; १८४, ४; १८५, १; ८;

११; १८६, ९^{२}; १८७, ७–९; **२.**
१, १५; ४, ५; ५, ३; १०,
१; ११, १०; १३, ३; ९; ११;
१३; १४, ८; १२; १६, ३; १७,
१^{२}; ३; १९, २; २०, ८; २२, ४;
२३, १४; १५^{२}; १८; २४, ९;
१५; १६; २७, ५; १४; २९, ५;
३०, ३; ३१, १; २; ५; ३४, २;
८; १०^{२}; ३५, १५; ३८, ११;
४१, ८; ४३, ३; **३.** २, ७; ५, ४;
६, ७; ८, १^{२}; ९, २^{२}; ६; ७; १४,
३; ४; १८, ५; १९, ४; ५; २२,
२^{२}; २९, ११^{२}; १४^{२}; १६; ३०, ५;
१२–१४; १८; ३१, १७; ३२, १;
६; ९–११; १४; १६; ३३, ७; ८;
११; ३६, ४; ६^{२}; ८; ९; ३८, ९;
३९, १; ४०, ९; ४८, २; ५१, ८;
५२, ५; ५३, ८; ९; ५४, १७;
५५, १; ११; १७; ५७, २; **४.** १,
१०^{२}; २, १४; १८; ५, ८; ९;
११^{३}; १२; ६, ५; ६; ७, ७;
९–११; ११, २; ६; १२, ४; १३,
२; १५, ७; १६, ३; ४^{२}; ८; ११;
१४; १७^{२}; १७, १९; २०; १८,
१२; २०, १०; २१, ७^{३}; ८; २२,
१^{२}; ५; ७; २३, ४; २४, ३; ४; ८;
२६, ३; ४; २७, ३^{३}; ३०, ३; ८;
१०; १३; २३; ३१, ६; ३२, ८;
३३, ४^{३}; ७; ३५, २; ९; ३६, १;
३; ३९, ४; ४१, ११; ४२, ६^{२};
४३, ५^{२}; ७; ४४, २; ५; ६; ४५,
५; ५१, ६; ५४, ३; ४; ५५, २;
५६, १; ५७, ५; ५८, १; **५.** १,
३; ४; २, २; ३, १^{२}; २^{२}; ३^{२}; ८;
४, ६; ६, ४; ७, ३; ४; ८; ९,
५; १५, ४^{२}; २५, ७; २९, २^{२};
५; ६; ८^{२}; ९; ३०, ५; ७; १०^{२};
११; ३१, ३; ५; ६; ७; ८; ३२,
१; ५; ७^{२}; १०; ३३, ३; ४; ३४,
२; ८; ३५, २^{३}; ३८, २; ३९,
१–३; ४०, ५; ६; ४२, २^{२}; ४;
४४, १२; ४५, ८–१०; ४७, ५^{२};
४८, १; ४९, ४; ५३, १; ७; १३;
५४, ४; ५; ६; ८; १०; १२; ५५,

६; ८^{४}; ५७, ३; ५८, ६; ५९, ४;
६०, ३; ६^{३}; ७; ६२, ९; ६४, ३;
४; ६६, ६; ६७, २; ७३, १^{४};
४–८; ७४, ४; १०; ७८, ४; ८२,
५; ८३, २–४; ९^{२}; ८४, ३; ८५,
६; ७; ८^{२}; **६.** २, ३; ९; ३, ३;
५, ६; ७, ४; ५; ९, ६; ११, ३;
५; १२, ५; १३, ५; १५, १; ९;
१४; १६, ३६; १७, ८; ९; १८,
१३; १५; २०, २; ३; ५; १०;
२३, १; २^{२}; ५; २५, ४^{२}; ७; २६,
१; ५; ७; २७, ४; ५; ३०, ३;
३३, ४; ३४, ३; ४; ३५, २; ५;
३६, १; ४०, ५^{३}; ४४, ६; ४५,
२२; २३; ४६, ७^{२}; ८^{२}; ११; १३;
४७, १०; १५; ५०, ४; ५; ५१,
७; ५६, ४; ५७, ४; ६२, ३;
८; ६३, २; ६५, ४; ६६, २;
४; ६७, २; ४; ५^{२}; ७^{२}; ८–१०;
११^{२}; ६८, ४; ६९, ८; ७०, २;
७४, ३; ७५, १; **७.** ३, ४; ६; ९;
५, ३; ८, ४; १३, ३; १६, ४;
१८, १; १९, २; ५; २०, १; ७;
२३, २; २५, १; २६, १; २; २७,
१; ३; २८, २^{२}; ३–५; ३०, ३^{२};
३२, ७; १८; २१; ३३, ४; १०^{२};
३४, २०; ३६, ६; ४०, १; २;
६; ५०, २; ३^{३}; ५२, २; ५३, ३;
५४, १; ५५, २; ५६, ४; १०;
२१; २२; ५७, १; ४; ५८, ५^{२};
६०, १; ८; ६१, २; ६३, २; ६६,
४; १२; १४; ६७, ४; ६८, ४–६;
६९, ४; ७०, १; ४; ७१, ४; ८१,
५^{२}; ८२, ५; ६; ८; ९; ८६, ४;
८८, २; ३^{३}; ५; ८९, २; ५^{२}; ९२,
२; ९३, ३; ५; ९४, ९; १०; ९६,
२; ९८, २; ४^{२}; ६; १००, ६^{२};
१०३, २; ३; ४^{२}; ५^{२}; ७; १०४,
१२; **८.** १, ३; ११; २८; ३१;
२, ६; ३, ११; १२; ४, १; २;
५, १; २४; ६, २; ३; ५; ८; १३;
२४–२६; ३०; ७, १; २; ४; ५;
११; १४; २१; २६; २८; ३१; ८,
६; १०; ९, २^{३}; ५^{३}; ६^{२}; ९^{२};

१०^{४}; १२^{४}; १३^{२}; १५; १८; १९^{२};
२१^{२}; १०, १^{३}; २; ५^{३}; ६^{३}; १२,
७; १३–१५; १६^{३}; १७; १८;
२५; ३२; १३, ५; ६^{२}; १५^{३};
२९; १४, १; २; ४; ५; ७; १३;
१५, १२; १८, ३; १२; १९, १५;
२५; २०, ४; २५^{४}; २२, १०;
११; २३, १३; २४, ३०; २५,
१३^{२}; २६, १७; २७, ९; १९^{२};
२०; २१^{२}; ३४, १६; ४०, ७; ४१,
८; ४३, ६; २८; ३३; ४४, २३;
४५, ६; ७; १४; १८; १९; ३१;
३९; ४१^{२}; ४६, ३१; ४७, १०^{४};
१३^{२}; १४^{२}; ४८, ९; ४९, ७^{३};
५०, २; ३; ५४, ५; ५९, १; ६;
६०, १४; ६१, ९; ११; ६२, १;
५; ८; ६३, ७; ६५, २^{२}; ६६, ५;
६७, ६^{२}; ६९, ६; ७; १०; १७; ७०,
५; १४; ७२, ६; ७३, ५; ७५, ३;
७६, ११; ७९, २^{२}; ६; ९; ८३,
५; ८८, ३; ६; ८९, ५; ६^{२}; ९१,
६; ९३, ४; ५; १४; १७; ९६, ५;
१२; ९७, ५^{३}; ११; ९९, ६; १००,
५; ६; १०; १०१, ८; १०२, २०;
२१^{२}; **९.** २, ४; ७, ४; ५; १९,
१; २४, ५; ४३, ५; ४७, ३; ५०,
२; ५६, २; ६१, २७; ६४, १९;
२०; ६५, ६; ६६, ९; १३; ६७,
२१^{२}; २३; २४; ६८, ६; ७०, १;
६; ७१, ५; ७२, २; ७४, १; ७;
८१, १; २; ८६, १५; ४७; ८७,
३; ९२, ५; ९४, १; ३; ९५, ५;
९७, ३१; ४१; ९९, ७; १०२, २;
४; ५; ७; ११०, ८; ९; १११, १;
३; ११४, ४; **१०.** १, ३; २,
३–५; ३, २; ८, ५; १०, २; ४;
११^{२}; ११, ३; ५; ८^{२}; १२, १;
३; ४; १३, २; १६, ६; १७, २;
१८, २; १९, ४^{२}; २०, ४; २२,
७; ११; १४; २३, ६; २४, ४;
२५, ९; २७, ४; ५; ९; १०; १२;
२८, ३; २९, ४; ३०, ५; ६; १३;
३१, ५; ८; १०^{३}; ३२, १; ३; ४^{२};
३३, ८; ३४, ५; ३५, ८; ३६,

१०; ३७, २; ३; ५; १२; ४०, ११; ४१, ३; ४२, ९; ४३, ५; ७; ४५, २; ६; ८; ४७, ८; ४८, ४; ८; ९; ४९, ४–७; १०; ५१, ७; ५२, १; ३; ५४, १^{२}; २; ३; ५५, २; ४^{२}; ६; ५८, १; २^{२}; ३–६; ७^{२}; ८^{२}; ९–१२; ५९, ८; ६१, १; ४–७; ११; १३; १७; २०; २३; ६८, ७; ६९, १; ३^{२}; ४; ९; ७०, ९^{२}; ७१, १^{३}; ६; ८; ७२, ६; ७; ७३, १; ३; ९^{२}; १०; ७४, ६^{२}; ७५, २^{२}; ३; ४; ७६, २; ७७, ६; ८१, ४; ८२, ५; ८५, ३; ५; ७; ९; १४–१६; २०; ८६, २०; २२; ८७, ६; १३^{२}; ८८, ४–६; १५; ८९, ६; १४^{२}; ९०, २^{३}; ६; ११; १२; १५; ९१, ५; ७; ९; ९३, ५; ९४, १; ६; ९५, ७–९; १२; १३; १६; ९६, ९; ९७, ५; ९–११; ९८, १^{२}; ७; ९९, ३; ८; ११; १०२, २; १२; १०५, ३; ९; ११^{२}; १०७, ७; ८; १०८, १०; १११, ७^{२}; ११३, १; ३; ६; ११८, २; १२०, ३; १२१, ७; १२३, ६; ८; १२४, २; १२६, ७; १२९, १; ३; ४; १३०, ३; १३१, ५; १३२, ३^{२}; ५; १३४, १; ४; १३५, ७; १३६, २; ७; १३७, २; ३; १३८, ६; १४२, ४; ५; १४३, ४; १४६, २; १४७, १^{२}; १५५, ३; ४; १५७, ४; १६४, ३^{२}; ४; १६५, १; ४^{२}; १७२, १; १८१, १; २^{२}; १८६, ३.

यतः **१.** २२, १६; १९; २५, १७; १२८, ४; १४१, १; **२.** २४, ६; **३.** ४, ९; १०, ६; १३, ४; २९, १०; **४.** १८, १; **५.** ४८, ५; **७.** ४, २; ७, ३; ७६, ३; **८.** ६, २९; ६१, १३; **१०.** ३१, ७; ४५, २; ७३, १०; ८१, २; ८५, ३१; १२०, १; १२९, ६; ७.

युतः **१.** १६९, १; **५.** ५३, १६; **६.** ४६, १४; **७.** ६१, ३; **९.** २४, ३; २८, ४; ६४, १५; २९; ६८, ४; ७; ८६, २०; २२; ९५, १; ९९, ८; १०८, १५; **१०.** १११, ७.

यतंऽङ्कुरः **५.** ३४, ४.

यतंतं **८.** ३५, १२.

यतति **७.** ३६, २.

यतंते **१.** १८६, ११; **३.** १६, ४.

यतते **१.** ९५, ७; ९८, १; **५.** ३७, १; **९.** ९२, ३; १११, ३; **१०.** ७५, ३.

यतंथः **५.** ६५, ६.

यतथः **५.** ७४, २; **६.** ६७, ३; १०.

यतन् **५.** ४८, ५.

यतंतां **५.** ५९, ८.

यतंते **८.** ४३, ४.

यतंते **१.** १६३, १०; **७.** ७६, ५; ७९, २; **१०.** २९, ८; ९१, ७.

यतं **९.** ३४, ३.

यतमः **१०.** ८७, ८; १७.

यतंमानः **५.** ४, ४.

यतंमाना **१०.** ६२, ११.

यतंमानाः **१.** १२३, १२; **३.** ५८, ८; **१०.** १८, ६.

यतंमाने इति **१०.** १३, २.

यतमानौ **१०.** ११३, ७.

यतंयः **८.** ६, १८; **१०.** ७२, ७.

यतंये **७.** १३, १.

यतरत् **७.** १०४, १२.

यतऽरश्मयः **५.** ६२, ४.

यतऽस्रुक् **४.** २, ९; १२, १.

यतऽस्रुचः **१.** १४२, ५; **२.** ३४, ११; **३.** २, ५; ८, ७; २७, ६; **८.** २३, २०; ४६, १२; ७४, ६.

यतऽस्रुचा **१.** ८३, ३; १०८, ४.

यतऽस्रुचे **१.** १४२, १.

यतस्व **१.** १६९, ६.

यता **४.** ६, ३.

यतानः **९.** ९७, ३०.

यतानाः **३.** ८, ९; **५.** ३३, १०.

यति **७.** ४३, ४; **१०.** १५, १३; १८, ६; ६३, ६.

यतिः **९.** ७१, ७.

यतिऽभ्यः **८.** ३, ९.

यतऽइव **१.** १६४, ३७.

यती **५.** ४५, ७; ५९, २; **७.** ९५, २; **१०.** ४०, ५.

यतीऽइव **७.** ७६, ३.

यतीः **८.** ६, ३४; १३, ८; ९१, ४; **९.** २४, २.

यतीःऽइव **५.** ५३, ५.

यतीनां **१.** १५८, ६.

यतीषु **४.** ३८, ७.

यतुनस्य **५.** ४४, ८.

यते **१.** ४१, ४; १८८, २; **५.** २७, ४; **८.** २७, २०; **९.** ६९, ३; ७४, ३; ७७, ५; **१०.** ७८, २.

यतेते इति **१०.** १३, ५.

यतेम **६.** १, १०.

यतेमहि **५.** ६६, ६.

यतैते इति **७.** ९३, ५.

यत्ऽयंत् **८.** ६१, ६.

यत्र **१.** १३, ५; २२, ४; २३, १८; २८, १–४; ८३, ६; ८९, ९^{२}; ११३, १६; ११५, २; १२१, ९; १३३, १; १३५, ७; १५१, ६; १५४, ५; ६; १६३, ४; १६४, २; ३; २१; ३४; ५०; १६६, ६; १८८, ४; **२.** २४, ८; **३.** १, ८; ७, ६; ३१, १; ३२, १४; ३९, ५; ५३, ५; ५४, ९; ५५, १२; **४.** २३, ७; ३०, ४–६; ५८, ९^{२}; **५.** ५, १०; ४४, ९; ५०, ४; ५५, ७; ६१, १४; ६२, १; **६.** १६, १७; १८, १४; ३१, ४; ४०, ५; ४६, १२; ७५, ८; ११; १७; **७.** १, ४; १४; ६३, ५; ६५, २; ८३, २^{२}; ६; ८; ९७, १^{२}; **८.** ४, १२; १३, २०; २०, ६; २९, ७; ४८, ११; ५३, ४; ६९, ५; ७५, १५; **९.** १५, २; २५, ४; २९, ५; ३९, १; ७१, ८; ९२, ५; १११, २; ११३, ६; ७; ८^{२}; ९^{२}; १०^{२}; ११^{२}; **१०.** ८, ६; १०, १०; १४, २; १७, ४^{२}; २८, ८; ३१, ९; ३७, २; ३८, १; ४४, ७; ६४, १३; १५; ७१, २; ७४, २; ७६, ६; ८२, २; ५; ८६, १; ८७, ६; ८८, १७; ९०,

१६; ९७, ६; ९९, ४; ११४, ३; १२१, ६; १३८, १; १४९, २.

यत्रंऽयत्र ६. ७५, ६.

यथा १. ६, ६; १०, ५; २३, १३; ३०, १२; ३९, ७; ४३, २^{३}; ३^{२}; ५१, १२; ७६, ५; ८३, १; २; ८९, १; ५; १११, २; ११३, १; ११४, १; १२७, ४; १२९, ५; १३२, २; १३८, २; १४३, ५; १५६, ३; १७०, ३; १७३, १; ९^{२}; १७५, ६; १७६, ६; १८६, १–३; २. ४, ९; ५, ८; १४, १०; २२, १; २४, १; २६, २; ३०, ४; ११; ३३, १५; ३. ४, ६; १०; १७, २^{२}; ३२, १४; ३५, २; ३६, ३; ६; ४८, १; ५१, ७; ५४, ६; ४. २, १६; १२, ६; १६, २०; ३०, १; ३७, १; ३; ४२, १; ५४, १; ४; ५५, ३; ५७, ६^{२}; ५. २०, ४; ४०, ५; ५४, ८; १३; ५५, २; ५६, २; ५९, ७; ६१, ४; १०; ७८, ७; ८^{३}; ७९, १; ९; ६. ४, १; १९, ४; २३, ५; ९; १०; ३४, ५; ३६, ५; ४४, १६; ४५, ५; ४८, १५; १९; ५०, ३; ६३, २; ७. ३, ७; २४, १; २६, १; ३१, २; ३२, २६; ५५, ६; ५६, २०; ५७, ३; ६४, ३; ९७, २; १००, २; १०४, ३; २१; ८. २, ३; ३, १२; ४, ३; ५, ३; २५; २६^{२}; ३७; १३, १४; २९; १४, १; २०, १७; २३, ६; २४, ९; २८; २८, ४; ३१, १३; ३२, २३; ३६, ७; ३८, ९; ४२, ५; ४५, ८; १३; १६; २४; ४६, १०; १४; २१; ४७, २; १७^{३}; ४९, १; ४; ९^{२}; १०^{३}; ५०, ९; १०; ५१, १; ५२, १^{२}; २; ५४, २^{२}; ६०, ७; ६१, ४; ६६, ४; ६७, २; ६८, १; १०; ६९, ४; ७५, १६; ८२, २; १०२, ८; ९. ३२, ३; ५; ५५, २^{२}; ७६, ५; ८२, ५; ८६, २; १३; ३२; ८८, ७; ९१, १; ९६, १२; १०४, ३^{२}; १०६, २; १०७, १३; १०. ४, १; ७, ६; ११, १; १८, ५^{२}; ११; २३, ४; ३६, ११; ३७, १०; ३८, २; ३९, ४; ५; ४३, १; ४४, ४; ५१, ७; ५२, १^{२}; ५; ६०, ८; ९; ६४, १३; ७३, ६; ७६, १; ३; ८५, २५; २६; ३६; ९१, ७; ९५, १८; ९६, २; १२; १००, ३; १०३, १३; १३१, १; २; १३३, ७; १३४, ६; १३५, ५; ६; १३७, ५; १४१, ४; १४९, ५; १५१, ३; १५९, ६; १६१, ३; १६६, ३; १७४, ३; ५; १९१, २; ४.

यथा १. २५, १; २६, ४; ३०, १; ५०, २; ३; १३०, ६; २. ४३, ३; ३. ४५, ३; ५. ९, ३; ५; २५, ८; ५३, ७; ५४, ४; ८७, ७; ७. १५, ५; ८. १, २; २१, ५; १५; २९, ६; ४७, ५; ११; ६०, १३; ७५, ५; १२; ८६, ४; १०२, ६; ९. ३६, १; ६४, २९; १००, ४; १०. १८, १४; २२, ९; ७२, ७; ९७, ११; १३४, ६.

यथाऽइव १०. ८६, ७.

यथाऽकामं १०. १४६, ५.

यथाऽकृतं ७. १८, १०.

यथापूर्वं १०. १९०, ३.

यथाऽयथा ४. १९, १०; ५४, ५; ८. ३९, ४; १०. १००, ४; १११, १.

यथाऽवशं २. २४, १४; ३. ४८, ४; ५. ३४, ६; ७. १०१, ३; १०. १५, १४; १६८, ४.

यदंवे ५. ३१, ८.

यदा १. ८२, १; १०३, ८; ११५, ४; १६१, ४; १६३, ७; १६४, ३७; ३. ५३, ४; ४. १७, १०; २४, ८; १०; ३३, २; ३८, ८; ५. ८५, ४; ८७, ४; ७. ३, २; ४२, ४; ९८, ५; ८. १२, २६–३०; २१, १४; ५१, ८; ८०, ९; १००, १; १०. १६, १; २^{२}; २३, ३; २७, ३; ६७, १०; ६८, ६; ८२, १; ८८, ११^{२}; ९२, ३; ११४, १०; १४२, ४.

यदि १. ११, ३; २७, १३; ३०, ८; ५६, ४; ७९, २; १६१, २; ८; १६८, ८; १७३, ८; १७८, ३; २. ५, ६; ३. ५, ८; १०; ६, ३; २९, ६; ३१, २; ६; १३; ४. ५, ११; २१, ६; ८; २६, ५; २७, ३; ४१, ३; ५. २, ११; ३, १०; ४८, ४; ७४, ५; ६. २२, ४; २५, ६^{२}; ३४, ३; ४२, ३; ४६, १४; ७. ५६, १५; ८२, ८; १०४, १४; १५^{२}; ८. १, १५; १२, ८; १३, २१; १९, २३; ३२, ६; ३३, ९; ६१, १०; १००, ३; ९. १४, २; ३; १५, ३; ४७, ४; ७०, २; ७२, २; ८६, ६; ४६; ९७, २२; ९९, २; १०. ११, ४; १२, ३; १६, ३; २२, १०; २७, २; ६१, २५; ९५, ४; ११५, १; १२९, ७^{२}; १४३, १; १६१, १; २^{३}; १६७, ४; १७९, १^{२}.

यदुः १०. ६२, १०.

यदुं १. ३६, १८; ५४, ६; १७४, ९; ६. ४५, १; ८. ४, ७; ७, १८; ९. ६१, २; १०. ४९, ८.

यदुषु १. १०८, ८.

यदौ ८. ९, १४; १०, ५; ४५, २७.

यन् १. १७३, ३; १८३, २; ४. २४, ९; ५. ३१, ७; ६. ३, ७; ८. २, ४०; ४३, ७; ९. ९३, २; १०. १२, १; ८८, १२; ९९, ३; ११७, ७; १२४, २.

यन् ३. ४, ५.

यन्ऽइव ९. ३, ४.

यंतं ८. २७, ४.

यंत १. ८५, १२; ५. ४६, २; ६. ५१, ५; ८. १८, २१.

यंतः १. १४०, १३; ७. ७४, ५; ८. ४५, ११; ६१, ४; ९८, ७; १०. १२३, ४.

यंतन ५. ५५, ९; ८. ४७, ३; १०.

यंतं १. १०५, १८; ५. ५४, ६; ६. १, ३.

यंतं ५. ६७, २.

यंतं ४. ५५, ४; ५. ६४, २; ८. ५, १२.

यंतवे ८. १५, ३.

यंता १. २७, ७; १३१, ३; १८३, ५.
यंता २. २३, १९; २४, १६; ३. १३, ३; ८. ७९, ३; १०. २२, ५; ४६, १.
यंतारः ७. १६, ७.
यंतारं ३. ३, ८.
यंतारा १. १६२, १९.
यंति १. ९७, ५; १००, ३; १२२, १३; १२३, १२; १९०, ४; ७; २. ३५, ३; ३. ९, ३; १४, ६; ४. ४७, २; ५. ६, १; ८. २, १८; ५, ३९; ७९, ५; ९. ९५, ३; १०. १८, ५; २६, १; ८५, २३; ३१.
यंति १. ५, ५; २३, १६; २५, १६; ३१, १०; ३२, ८; ५०, २; ७१, ३; ८३, २; ९२, १; ११३, ११; ११५, ३; ११९, २; १२३, ८; १२; १२५, ४; १४०, ७; १६३, १२; १८०, ४; २. १३, २; २८, ४; ३०, २; ३५, ३; ४; ९; ३. ८, ९; १२, ७; ३१, १४; ४०, ४; ५१, २; ४. १३, २; ५. १०, ५; २१, २; ४१, १३; ४४, १४; १५; ४७, २; ६; ५१, ७; ५३, ६; १०; ६. ९, ५; १३, १; २८, ४; ३४, १; ७. १, ३; १०, ३; १५, ९; २१, २; ४७, ३; ४९, १; ८. ३९, १०; ४०, ८; ४६, ३०^{२}; ९३, २२; १००, १; १०३, ६; ९. ३३, १; ५७, १; ६२, २८; ६९, ४^{२}; ९; ७२, ६; ८१, १; ८६, ५; ६; ४७; ९६, २४; ९७, ३४^{२}; ११३, ५; १०. २५, ४; ३१, ३; ८२, ३; ९२, ५; ९४, ५; १३६, २.
यंतु ७. १०४, ५.
यंतु १. ४०, १; ८९, १; ९१, १८; १२५, ७; १३९, १; १६७, १; ३. २६, ४; ३०, २१; ४. ५७, ८; ५. ४३, १; ५८, ३; ६२, ४; ८७, १; ७. ३४, १८; ३७, ८; ८. २३, १०; ४४, ५; ७१, १०; १००, १२; ९. १०६, १; १०. ३१, ५; ६४, ९; ६६, १०; ८४, १; ८७, १५; १०३, ८; १०; १०८, ११; १२८, ६.
यंतुरं ३. २७, ११; ८. १९, २.
यंतौ १. १३९, ४.
यंत्रं १. ३४, १.
यंत्रैः १०. १४९, १.
यंधि ७. ८८, ६.
यंधि १. १२१, १४; ३. ३६, ९; १०; ४. २, २०; ३२, ७; ६. २४, ९; ७. ७५, २; ८. ६८, १२.
यं १. १, ४; १८, ४; २४, १२; २५, १४; २७, ७^{२}; ३०, ९; ३१, १६; ३६, १; १०^{४}; ११; १९; ४१, १; २; ५; ४९, २; ५२, ४; ५८, ७; ५९, ६; ६०, ३; ६४, १३; ७०, ४; ७१, ६; ९४, १५; ९५, ६; १०१, ६; १०२, ३; ११६, ६; १२१, १२; १२७, २; १२८, २; १२९, १; ४^{२}; १३५, ८; १४३, ४; १४४, ४; १४८, १; ३; ५; १५१, १; १६६, ८^{२}; १७२, २; १७६, २; १८२, ७; १८६, ५; १९०, ७; २. २, ११; ५, ८; ११, १३; १२, ५; ८; ९; १७, ६; २३, ५; २४, ४; २७, १२; ३०, ६; ३५, ११; ३७, २; ३. २, १३; ४, २; ८, ११; २९, ७; ४३, ७; ४६, ५; ४९, १; २; ५३, २१; ४. ३, २; ३; ६, ८; ७, १; ११, ६; १३, ३; १७, ९; १८, ४; ३४, ३; ३५, ४; ३६, ५^{२}; ६^{२}; ३७, ६; ३८, ३; ३९, २; ४३, २; ५. ६, १; २; ७, २; ६; ९, २; ३; १६, १; २०, १; २५, २^{२}; २८, २; ३१, १; ४०, ९; ४३, ७; ५३, ६; १५; ५४, ७; ६२, ६; ६३, १; ८६, १; ६. ३, १; ९, २; १०, २; ६; ११, ४; १३, ३; १५, २; १७; १६, ४०; १७, १; ११; २४, ७; ३४, ३; ३८, ४; ४४, ५; ४८, ५; ५८, ४; ६६, ७; ८^{२}; ६८, ६; ७. १, ५; ६; १२; १६^{२}; २३; ४, ३; ७, ५^{२}; २२, १; ३७, ७^{२}; ३८, ३; ४०, ३; ४१, २^{२}; ४७, १; ५६, १५; ५९, १^{२}; ७८, ४; ९०, ३; ८. २, ५; ३५; ३, १०; २१; ४, १६; १२, १३; २४; १३, २३; ३२; १९, २१; ३४; २२, १; २३, ८; २७, १७; ३६, १; ४३, २७; ४५, ९; २१; ४६, ४^{२}; ४७, १; ६; ४८, १; ४९, ५; ५०, ५; ५८, १; ६१, १२; ६३, ६; ६६, २; ६८, ५; ७१, ५; ७४, २; ६; ११; १२; ७७, ७; ८२, ९; ८४, २; ९; ८८, ४; ९५, ६; ९७, २; १०३, ४; ९. ६, ५; १४, ६; ७७, २; ७८, ४; ८०, २; ८८, १; ९७, ३७; ९८, ६; ९९, ३; १०२, ६; १०. २, ७^{३}; ४, २; ५; ६, ५; ७, ४; १६, १३; २०, ३; २१, ४; २३, ३; २८, ५; २९, ८; ३०, ४; ३२, ९; ३५, १४^{३}; ३९, ११; १२; ४२, ८; ४६, ९^{२}; १०; ५३, १; ६३, ६; १३; ६९, ४; ८५, ३; १३; ८६, ४; १५; ८८, ४; ९; ९६, २; ९७, १७; ९८, ८; १०२, १०; १०४, २; ११२, ६; १२०, १; १२१, ६; १२५, ५; १२६, १; १३५, ३; ४; १४३, २; १४४, ४; ५; १६४, ५; १८४, ३.
यमं १०. १४, ५.
यम १०. १०, १३; १४, ४; ११; १५४, ४; ५.
यमः ५. ६१, २.
यमः १. ६६, ४^{२}; १६३, ३; १०. १३, ४; १४, २; ३; ९; १५, ८; १८, १३; ५१, ३; ९२, ११; ११४, १०; १३५, १.
यमः १०. १३४, ६.
यमंत् ५. ३४, २.
यमत् ५. ४६, ५; ८. ११, ७; ३३, ८; ९२, ३; ९. ४४, ५; १०. १४, १४.
यमंति १. १४१, ११.
यमति १. १००, ९.
यमंतुः ६. ६७, १.
यमते १. १२७, ३; ६. ४५, २३; ७. २७, ४; ३७, ३; ८. २, २६.

यमन् ३. ४५, १; ४. ४४, ५; ७. ६९, ६; ८. ९२, ३१.
यमं १. ७३, १०; २. ५, १; ३. २७, ३; ८. २४, २२; १०३, १०.
यमं १. १६४, ४६; १०. १४, १; ७; १३; ५८, १; ६४, ३.
यमं १०. ४९, ३.
यमय ८. ३, २.
यमयंति १. १६२, १६.
यमयोः १०. ८, ४; ११७, ९.
यमऽराज्ञः १०. १६, ९.
यमसानः ६. ३, ४.
यमऽसूः ३. ३९, ३.
यमसे ५. ३३, ३.
यमस्य १. ३५, ६; ३८, ५; ८३, ५; ११६, २; १०. १०, ७; ९; १२, ६; १४, १२; १७, १; २१, ५; ५२, ३; ९७, १६; १२३, ६; १३५, ७.
यमा २. ३९, २; ३. ३९, ३; ९. ६८, ५.
यमाः १. १६४, १५.
यमाःऽइव ५. ५७, ४.
यमात् १०. ६०, १०.
यमाय १०. १४, १३[२]; १४; १५; १६५, ४.
यमि १०. १०, १४.
यमिंतवैऽइव १. २८, ४.
यमिष्ट ५. ३२, ७.
यमिष्ठा ६. ६७, १.
यमिष्ठासः १. ५५, ७.
यमीः १०. १०, ९.
यमीमहि १०. ३६, ८.
यमुः ५. ६१, ३.
यमुनां ७. १८, १९.
यमुनायां ५. ५२, १७.
यमुने १०. ७५, ५.
यमे १०. १४, १६.
यमे इवेति यमेऽइव १०. १३, २.
यमेन १. १६३, २; ७. ३३, ९; १०. १४, ८; १०.
यमौ ६. ५९, २.
यम्यः ५. ४४, ४.
यम्यं १०. १०, ७.
यंऽस्य २. २५, १–५.
यंयमीति १. ९५, ७.
यम्यां ३. ५५, ११; ५. ४७, ५; ९. ६८, ३.
यम्याः ४. २२, ८; ६. २३, ८.
यय ८. ३४, १.
यय ५. ६१, २.
ययथुः १. ११७, १६.
ययंथ १. ५९, १.
ययस्तु ८. १०४, २.
यया १. ६३, ८; १२०, ५; १७८, १; २. ३४, १५[२]; ३. ६०, २; ४. २०, ९; ५१, ६; ५. ४५, ६[२]; ११; ६. २२, १०; ३७, ४; ४१, २; ७. ५, ८; ८. ४२, ३; ९. ३५, १; ४५, ६; ४९, २; ६३, ७; १०. ९८, ३; १०५, १०; १४५, १[२]; १५६, २.
ययातिऽवत् १. ३१, १७.
ययातेः १०. ६३, १.
ययाथ ३. ३३, १०; १०. १७, ८.
ययाथ ५. २९, ९; ६. ४०, ४.
ययाम ७. ३८, १.
ययिः ५. ७३, ७; ८७, ५.
ययिना १०. ९२, ५.
ययिं १. ५१, ११; ८७, २.
ययियः १०. ७८, ७.
ययिऽवान् ९. १५, ६.
ययुः २. ५, ५; ५. ८१, ३; ७. ७४, ६; ८. ७, २९; ९. ८६, ४६; १०. १७, ४; १५४, २.
ययुः १. १६८, ४; ४. १९, ५; ५. ५३, २; १२; ६. ६५, २; ७. ८३, १; ८. ७, २३; ९. ६९, ९.
ययोः २. ३२, १; ३. ४४, ३; ५०, २; ५४, २; ६. ६०, ४; ७. ६५, १; ८. १०, ३; ४; ४०, ४; ५९, २; ९. ५८, ४; १०. २२, ५; ६५, ५[२].
ययौ ३. ३३, ९.
ययौ ४. २६, ५; ९. ८७, ८.
यय्यं २. ३७, ५.
यवऽअर्दः १०. २७, ९.
यवऽआशिरः १. १८७, ९; ८. ९२, ४.
यवऽआशिरं २. २२, १; ३. ४२, ७.
यवः १. ६६, २; १३५, ८; २. ५, ६.
यवंत ५. २, ५.
यवं १. २३, १५; ११७, २१; १७६, २; ५. ८५, ३; ७. ३, ४; ८. २, ३; २२, ६; ६३, ९; १०. २७, ८; ४३, ७; १३१, २.
यवऽमत् ८. ९३, ३; ९. ६९, ८; १०. ४२, ७.
यवऽमंतः १०. १३१, २.
यवंऽइव १०. ६८, ३.
यवंऽयवं ९. ५५, १.
यवयं ६. ४६, ९; १२; ७. ७७, ४; १०. १२७, ६[२].
यवय १. ५, १०; १०. १०२, ३; १५२, ५.
यवयत्ऽद्वेषसं ४. ५२, ४.
यवयत्ऽद्वेषाः १. ११३, १२.
यवयत्ऽसखः १०. २६, ५.
यवयंतु ७. ४४, ३; ८. ४८, ५.
यवयसि ८. ३७, ४.
यवयस्व ५. ४२, ९.
यवऽयुः ८. ७८, ९.
यवसऽअर्दः १. ९४, ११; १०. २७, ९.
यवसं ३. ४५, ३; ५. ७८, २; ७. १०२, १; ८. ४, १८.
यवसस्य २. १६, ८; ७. ९३, २.
यवसाऽइव ४. ४१, ५; १०. ११, ५.
यवसात् ७. १८, १०.
यवसे १. ३८, ५; ५. ९, ४; ५३, १६; ६. २, ९; ७. ३, २; ८७, २; १०. २५, १; ९१, ८; १००, १०; ११५, २.
यवसेन ४. ४२, १०.
यवसेषु १. ९१, १३; ८. ९२, १२.
यवस्य १. ५३, २; ८. ७८, १०.
यविऽयुत् १०. ६१, ९.
यविऽयुधा ८. ४, ६.
यविष्ठ २. ६, ६.
यविष्ठ १. २२, १०; २६, २; १४१, १०; १४७, २; १८९, ४; २. ७, १; ३. १५, ३; १९, ४; ४. २,

१०; १३; ४, ६; ११; १२, ४; **५.** १, १०; ३, ११; **६.** १५, १४; ४८, ८; **७.** १, ३; ७, ३; **८.** २३, २८; ८४, ३; **१०.** १, ७; २, १; ४, २; ४५, ९; ६९, १०; ८०, ७; ८७, ८.

यविष्ठः **१.** १४१, ४; १६१, १; **४.** १२, ३; **६.** ६, २; **७.** ४, २.

यविष्ठं **१.** ४४, ४; **६.** ५, १; **७.** ३, ५; १०, ५; १२, १; **१०.** २०, २; १४३, २.

यविष्ठ्य **१.** ३६, १५.

यविष्ठ्य **१.** ३६, ६; ४४, ६; **३.** ९, ६; २८, २; **५.** ८, ६; **६.** १६, ११; ४८, ७; **७.** १६, १०; **८.** ६०, ४; ८; ७५, ३; १०२, ३; २०.

यविष्ठ्यं **५.** २६, ७.

यवेन **२.** १४, ११; **९.** ६८, ४; **१०.** ४२, १०.

यव्यं **१.** १४०, १३.

यव्या **१.** १६७, ४; १७३, १२.

यव्याभिः **८.** ९८, ८.

यव्याऽवत्यां **६.** २७, ६.

यशः **१.** १०, ७; २५, १५; **३.** ४०, ६; ६२, १; **४.** ३२, १२; **५.** ४, १०; ७९, ६; ७; **६.** २, १; **७.** १५, १२; ७४, ५; १०४, ११; **८.** १९, ६; २३, २१; १०३, ९; **९.** २०, ४; ३२, ६; ६१, २६; ९४, ३; १०६, १३; १०८, ९; **१०.** ३६, १०; १०६, ११.

यशःऽतमः **८.** २३, १०.

यशःऽतमं **७.** १६, ४; **८.** १०२, १०.

यशःऽतमस्य **२.** ८, १.

यशःऽतरः **९.** ९७, ३.

यशःतरं **८.** २, २२.

यशसः **३.** १, ११; **४.** ५१, ११; **७.** २१, २; ३६, ६; **८.** ४८, ५; **९.** ६१, २८; **१०.** ४६, १०; ६४, ११; ७६, ६.

यशसं **१.** १, ३; ३१, ८; ६०, १; ९२, ८; **२.** ३, ५; **३.** १, १९; **५.** ३२, ११; **६.** ८, ५; ४९, ९; **७.** ४२, ५; ७५, २; ९३, ४; **८.** ६१, ५; **१०.** ३९, २; ९१, १५

यशसा **१.** १२२, ४; **४.** १, १६; **५.** ८, ४; **७.** ६९, ३; **९.** ८१, १; **१०.** ७१, १०; १०६, २.

यशसां **६.** ३, २; **९.** ९७, ३.

यशसे **५.** १५, १.

यशसौ **५.** ४३, २.

यशस्वतः **१.** ९, ६; **८.** २३, २७; १०२, ८.

यशस्वता **३.** १६, ६.

यशस्वति **१०.** ३८, १.

यशस्वती **१०.** ११, ३.

यशस्वतीः **१.** ७९, १.

यशस्वान् **१०.** २०, ९.

यशाः **८.** २३, ३०; ९०, ५.

यष्टवे **१.** १३, ६; **४.** ३७, ७.

यष्टा **२.** ९, ६; **१०.** ६१, १७.

यष्टा **६.** ५२, १.

यस्मात् **१.** १८, ७; **२.** ९, ३; १२, ९; १६, २; **८.** ४७, १८; १०३, ३.

यस्मिन् **१.** ५, ९; ३३, १४; ४०, ५; १३२, ३; १६४, २२; ३९; १६८, ६; १७४, ५; **२.** २, ११; ५, २; १९, १; २०, ४; **३.** ३, ३; १६, २; २२, १; ३१, १३; ४९, १; **४.** ५०, ८; **५.** १६, ३; ३७, ४; ४४, ९; ५६, ८; ९; **६.** ५, २; १२, २; २९, २; ४; **७.** ४७, २; ८३, २; १०१, ४; **८.** २, ३३; १६, २; ४१, ६; ७०, ४; ९२, २०; १०३, १; **९.** ७१, ४; ११३, ७; **१०.** ६, ३; ६; १२, ७; ८; ४२, ६; ६१, २५; ६२, ११; ८२, ६; ८८, ९; ९१, १४; ९५, ४; १२०, ७; १३५, १.

यस्मै **१.** ९४, २; १५; १६६, ३; १२; **३.** ३०, ७; **५.** १, ९; ४, ११; ७, ८; **७.** ५९, ४; ६०, ४; **८.** ३, २३; ४७, ४; ७; ५१, ४; ६; ५२, ३; ८; **१०.** ३१, ४; ८६, ३; ९७, २०; २२; १८५, ३.

यस्य **१.** ५, ४; ११, ८; ३०, ५; ३३, ३; ५१, १; ५२, १; १४; ५४, ३; ५७, १; ३; ७४, ४; ८६, १; ३; ७; १००, २; ३; १४; १५; १०१, ३^{४}; १२२, १२; १२७, ३; ८; १३८, ३; १५४, २; ४; १७३, १२; १७६, ३; ५; १८७, १; १९०, १; **२.** १, ४; ८, ३; १२, १; ७^{४}; १४^{३}; १३, ९; ३५, ७; ३८, ९; **३.** ६, १०; १३, २; ३२, ७; ४३, ७^{२}; ५०, १; ५४, १४; **४.** २, १०; ६, ७; ९, ६; १७, १९; २०, ७; २१, १; २; ३४, ६; **५.** ७, २; ५; ९, ५; १७, ३; २७, ५; ३१, १२; ३४, ४^{२}; ३७, २; ४८, ३; ५४, १५; ६५, १; ८१, ३; ८३, ५^{३}; **६.** ३, ३; ७; ४, ३; १२, ३; १४, ४; ५; १८, ११; २१, २; २२, ५; २७, ७; ४०, २; ४१, ३; ४३, १–४; ४४, ६; ४५, ८; ३२; ४७, २; ४८, २१; ४९, ६; **७.** ३, ३; ४; ६, ६; ८, १; ११, २; १५, ५; १८, २४; २६, ४; २७, ४; ३१, ७; ३२, १०^{२}; ११; ६१, २; ८२, ७; ९२, १; ९७, ६; **८.** १२, १८; १३, १०; १५, २; १६, ४; १९, १०; ११; ३०; ३३; २०, १६; २४, २१; ४१, ९; ४५, ४२; ४६, ३; ५१, ९; ५२, ४; ५८, ३; ६३, १; ६८, ३; ८; ११; ६९, १२; ७०, २; ७४, ४; १०; ७५, १४; ८४, ७; ८६, ४; ९३, ११; १०२, १४; १०३, ११; **९.** ३५, ६; ६५, ८; १५; ६६, ३०; ८६, ९; ९७, ३८; १०८, २; १४^{२}; **१०.** ३, ५; ६, १; ८, ५; ९, ३; २०, २; २६, २; २७, ११; २९, १; ३३, ५; ६; ३४, ४; ३७, ९; ३९, १२; ४३, ६; ५०, १; ६०, ४; ६१, ५; १४; ८६, १२; १६^{२}; ८९, १; ६; ९३, ८; ९४, १०; ९६, ९; ९७, १२; १००, ११; १०५, २; १०८, ३; ११२, ४; ५; ११५, ४; १२१, २^{४}; ४^{४}; १४८, १; १५२, १; १५८, २; १६५, ४; १८१, १.

यस्याः १. ४८, १३; ४. २२, २; ५. ३, ५; ६. ६१, ८; ७५, १५; ८. ९४, २; १०. ८६, २३; १२७, ४.
यस्यां १०. ८५, ३७^{2}.
यहुः ८. ६०, १३.
यहो इति १. २६, १०; ७४, ५; ७९, ४; ७. १५, ११; ८. ४, ५; १९, १२; ८४, ५.
यह्व १०. ११०, ३.
यह्वः ३. १, १२; ५, ५; ९; ४. ५, २; ७, ११; ७. ६, ५; ८, २; ९. ७५, १; १०. ११, १.
यह्वतीः १. १०५, ११; ९. ११३, ८.
यह्वं १. ३६, १; ३. ३, ८; ४. ५, ६; ५. १६, ४; ८. १३, २०; २४; १०. ९२, २.
यह्वस्य ३. २, ९; २८, ४.
यह्वाः ४. ५८, ७.
यह्वाःऽइव ५. १, १.
यह्वी इति १. १४२, ७; ५. ५, ६; ४१, ७; ६. १७, ७; ९. १०२, ७; १०. ५९, ८; ९३, १.
यह्वीः १. ५९, ४; ७१, ७; ७२, ८; २. ३५, ९; १४; ३. १, ४; ६; ४. १३, ३; ५. २९, २; ९. ३३, ५; ९२, ४.
यह्वीभिः ३. १, ९.
यह्वीषु ७. ५६, २२; ७०, ३.
यह्व्यः १०. ९९, ४.
या १. २२, २; ३; २५, ११; ४६, २; ६; ४८, ६; ५९, ३^{2}; ८३, ३; ८५, १२; ९१, ४^{3}; १९; ९२, ८; १०७, १; १०८, ५; १२०, ५; १२६, ६; १२९, ८; १४०, १२^{2}; १५१, ४; १५५, १; २; १६१, ७; १६२, ८; १३; १६; १९; १६४, १९; १६५, १०; १७८, २; १८६, ११; २. १३, ११; २४, ५; ३२, ६; ७; ८^{4}; ३३, १३^{3}; ३४, १५; ४१, १८; ३. २२, ३; ३७, ९; ३९, १; ५४, ५; ५७, १; ५; ६; ४. ३८, १; ५०, ३; ९; ५. २९, १३^{2}; १४; १५; ३०, ३; १४; ३१, ६; ४१, १५; ४३, ४; ९^{2}; ४५, ६; ६१, ५; ७; ६८, २; ६९, ४; ७३, १०; ७९, २; १०; ८४, १–३; ८६, २^{3}; ६. १५, १४; २०, १३; २५, १^{3}; ४१, २^{2}; ४८, १२^{3}; ५३, ९; ६१, १; १३; ६२, १; ५; ६४, ५; ६५, १; ६७, १; ४^{2}; ६९, २; ७४, २; ७५, १५; ७. ४६, ३; ५६, २३; ६६, २; ७६, ३; ८१, ३; ४; ८६, ५; ९४, ११; ९८, ५; १०४, १७; २३; ८. ५, १३; १०, ४; २१, ४; २५, ६; ७; २७, ६; ३१, ५; ३३, १४; ४०, ५; ८; ४५, २५; ५९, २; ६१, १८; ९०, ३; ९१, ६; १००, ६; १०१, १३; ९. ६१, ३०; ८६, १८; १०. १७, ८; १९, ३; २३, २; ५४, ५; ५९, ७; ६३, १६; ६५, ५; ६; ७२, ५; ८१, ५^{3}; ८५, ३७; ८७, १३; ९५, ६; १०; १०७, ९; ११३, ७; १३३, ३; ७; १४५, ३; १४६, १.
याः १. २३, १७; ३२, ८; ४३, ९; ८४, १०; ९१, ९; ११३, १०^{2}; १८; १४४, १; १६३, ५; १६९, ४; १८८, ५; ८; २. ५, ५; ११, २; २३, ९^{2}; २७, १६; ३२, ५; ३. २०, ३; २२, ३; ५७, ३; ४. ३२, १०; ४७, ४; ५. ३३, २; ४४, २; ४६, ७^{2}; ६. २२, ११; २८, ५; ५८, ३; ७. ३, ८; ३६, ६; ४७, ४; ४९, १; २^{3}; ३; ५०, ४^{2}; ५५, ८^{2}; ६०, ३; ९१, ६^{2}; १०१, १; ८. २, २९; ३०; ३, ३; ६, २०; ९, १; ४०, ९; ५९, ४; ८०, १०; ९७, १; ९. ९, ४; १९, ५; ५३, १; ६२, ७; १०. १६, ४; ३०, २; ३५, ५; ८०, ६; ८३, २; ९७, १; १५^{3}; १८; २१^{2}; १००, १०; १०३, ११; १०४, ९; १०८, ५; ११; १११, ८; ९; ११४, २; १६९, २^{2}; ३; १७४, २; १८८, ३.
याचत १०. ४८, ५.
याचतात् ९. ८६, ४१.
याचन् ८. १, २०.
याचंते ९. ७८, ३.
याचंते ८. २, १०.
याचामहे १०. २२, ७.
याचामि १०. ९, ५.
याचिषत् ८. १, २०.
याचिषामहे ८. ६७, १.
याट् १०. ६१, २१.
यात् १. ८०, १५; ६. २१, ६; ७. ८८, ४^{2}; १०. ६८, १०.
यात् ९. ५२, २.
यात १. ३८, ११; ३. ३३, १२; ४. ३७, १.
यात १. ३७, १४; ८६, १०; ८८, १; १७१, २; ४. ३४, १; ५; ३५, १; ५. ४२, १०; ५३, ८; ७. ३८, ८; ५९, ४; ८. २७, ८; ५७, ३; ९. ९७, २०.
यातः १. ३२, १५; १४१, ८.
यातः १०. ८५, १८.
यातनं ७. ५९, ५.
यातन १. १६५, १३; ४. ३४, ६.
यातं १. ४६, ७; १०८, ६–१२; ११७, १०; १८४, ५; ४. १३, १; ४१, ११; ६. ६०, ३; ८. ५, ७; ९, ११; २२, ७; २६, १५; १०. १३१, ३; १४३, ५.
यातं १. २, ५; ६; ३, ३; ३०, १७; ३४, ४; ११; ४७, २; ९३, ११; १०८, १; ४; ११७, १; २; ११८, २; १०; ११; १३७, १; २; १८३, ५; ६; १८४, ६; २. ३९, ३; ५; ८; ४१, ३; ७; ३. २५, ४; ५८, २; ४. १४, १; ४४, ४; ५; ४७, ३; ५. ४३, ८; ७५, ७; ७६, १; ३; ४; ६. ६२, ७; १०; ११; ६७, ३; ६९, ३; ७. ५३, २; ६४, २; ६६, १७–१९; ६७, ३; ७; ६८, १; ६९, ३; ६; ७०, ५; ७१, ४; ७२, १; २; ५; ७४, ३; ४; ९१, ५; ६; ९३, ६; ८. ५, २४; ३२; ८, २–४; ६; ११; ९, ११; १४; १०, १; २२, ८; १२; २६, ७; १४; ३५, ७; १३; ५७, ४; ७३,

२; ८५, ८; ८७, ३; १०१, ७; १०. ३९, १२; १३; १०६, ११.
यातय १०. १२७, ७.
यातयति ३. ५९, १.
यातयत्ऽजनः १. १३६, ३^{२}; ३. ५९, ५.
यातयत्ऽजन ८. १०२, १२.
यातयत्ऽजना ५. ७२, २.
यातयन् ९. ३९, २; ८६, ४२.
यातयन्तं ५. ३२, १२.
यातयमानः ६. ६, ४.
यातयासे ५. ३, ९.
यातवः ७. २१, ५.
यातवे १. ३७, १०; ४४, ४; ११३, १६; १५७, १; ५. २९, १०; ८. ७, ८; १२, ३; २०, ६; ९. ६२, १७; १८; ६३, ८; ९; ६५, १६; ७८, २; ९९, २; १०. ७५, २; ६; १०६, १; १४३, १.
याता ८. ७०, १; १०. ९९, ३.
याताऽइव १. ७०, ६; ७. ३४, ५.
याताः ५. ३३, ५.
यातां ४. २८, ३; ५. ५५, १; ७. ४८, १; १०. १२, ५.
यातारं १. ३२, १४.
याति १. ३५, ३^{३}; ४. १५, २; २९, २; ६. ७५, १; ७. ४९, ३; ७५, ६; ८. ४५, ७.
याति १. ३५, २; ३; ४८, ५; ७; ५०, ९; ७७, ५; ११३, १४; १२२, १०; १२३, ४; १४०, ९; १६१, १४^{२}; २. २७, १२; १५; ३०, १; ३. २, १०; ५८, ८; ६१, ४; ४. १३, ५; ५. ६, ३; ३१, १; ८०, २; ६. २, २; ५१, १२; ६६, ७; ६८, १०; ७. ३८, ६; ७८, २; ९५, १; ९८, १; ८. ४, ९; ९, १८; २७, १७; ९. ९, १; १५, १; २५, ४; ४३, ३; ४४, ३; ७१, ८; ७८, १; ८६, ७; १५; ३२; ३३; ९१, ३; ९६, २; ९७, ४७; ५६; १०७, ८^{२}; १११, ३; १०. ८, १; ३२, ५; ८०, ५; १३९, १; १६८, १.

यातु १. ३५, १०; ११८, १; १५७, ३; ४. १६, १; २०, २; २१, १; ४८, ५; ५. ४५, ९; ७४, ८; ७. ४५, १; ६९, १; २; ८. २६, ४; २७, ८; १०. ७०, २; ११६, ४.
यातुः ८. ६०, २०.
यातुऽजूनां ४. ४, ५.
यातुऽधान ७. १०४, १५; १६.
यातुऽधानः ७. १०४, १५; १०. ८७, ८; ११; १५–१७.
यातुऽधानं ७. १०४, २४; १०. ८७, १२.
यातुऽधानस्य १०. ८७, ५; १०; २५.
यातुऽधाना १०. ८७, २४.
यातुऽधानाः १०. ८७, ९; १८; १२०, ४.
यातुऽधानात् १०. ८७, ७.
यातुऽधानान् १. ३५, १०; १०. ८७, २–४; १३; १४; १९.
यातुऽधान्यः १. १९१, ८; १०. ११८, ८.
यातुं ५. १२, २.
यातुऽमतीनां १. १३३, २; ३.
यातुमत्ऽभ्यः ७. १०४, २०; २५.
यातुऽमावतः १. ३६, २०.
यातुऽमावतां ७. १०४, २३; ८. ६०, २०.
यातुऽमावान् ७. १, ५.
यातूनां ७. १०४, २१.
यात्याः १०. ८५, १२.
यात्ऽराध्ये २. ३८, ८.
यात्ऽश्रेष्ठाभिः ३. ५३, २१.
याथ ६. ५०, ५.
याथुः १. ३९, १; २. ३४, ३; ३. ६०, ४.
याथः १. ३४, २; १८३, ३; ४. ४५, ७; ८. ९, १२.
याथः १. १३५, ७^{२}; १८०, ९; १८२, २; ३. ३३, २; ५. ७४, ३; ७५, ५; ६. ६२, २; ६३, २; ८. २६, २.
याथन १. २३, ११.
याथन १. ३९, ३; ५. ५५, ७; ५७, २.
यादमानः ३. ३६, १; ७. ६९, ३.
यादमानाः ३. ३६, ७; ६. १९, ५; ७. ७६, ५.

यादुरी १. १२६, ६.
यादृक् ५. ४४, ६.
यादृश्मिन् ५. ४४, ८.
याद्वः ८. १, ३१.
याद्वे ७. १९, ८; ८. ६, ४८.
याद्वानां ८. ६, ४६.
यान् १. ७३, ८; १२१, १२; २. ३४, १४; ३८, ३; ३. ८, ६; ३५, ९; ४७, ३; ४. ३५, ७; ६. ६६, ३; ८. ४०, ८; १०. १४, ३; १५, १३^{२}.
याने ४. ४३, ६.
यानान् १०. ७३, ७; ११०, २.
यानि १. १५, ८; ३२, १; ३६, ५; ५२, ७; १०८, ५; १६५, ९; १०; २. ३०, १०; ३३, १३; ३. १४, ७; ४. ३२, ११; ५. ३०, ३; ६. ३०, २; ५९, १; ७. २६, ३; ७०, ३; ८. ५९, ६; ९६, २; ९. ६६, ३; १०. ५०, ६; ५४, २; ५; ५६, ४; ९१, ३; १२८, ४.
यान्तः ४. २५, ८; ८. ८३, ६.
यान्तं ३. ३२, १४; १०. ४०, १.
यान्ता १. ११७, १२.
यान्ति १. ३७, १३; ८. ७, ४; २८.
यान्ति १. ८८, २; १६१, १४.
यान्तु १. १६७, २.
याभिः १. २३, १७; ३०, १३; ४५, ५; ४७, ५; ११२, १–३; ४^{२}–११^{२}; १२^{३}; १३^{२}; १४^{२}; १५^{३}; १६^{४}; १७^{२}; १८^{२}; १९^{३}; २०^{३}; २१^{२}–२३^{२}; १४४, २; २. २४, ८; ३२, ५; ३. ६०, १; २; ६. २८, ३; ७. ३, ८; ३७, ५; ९२, ३; ८. १, ८; ८, २०^{३}; २१; २०, २४^{३}; २२, १०^{२}; १२; ९. २, ७; ३८, ३; १०. ३०, ४; ५; ५३, १०; ७५, ६; १०४, ८.
याभ्यः ६. ४७, ३; ७. ४७, ४.
याभ्यां ८. ३८, १०.
यां १. १७, ९^{२}; ३२, १३; ८०, १६; ३, ३८, ८; ५३, १६; ६. ५३, ८; ७. २२, ३; ७७, ६; ७९, ४; १०४, ६; १०. १७, ९; ६४, १२.
यामः २. ३४, १०.

यामः १. ३४, १; १००, २; १६६, ४; १७२, १; ४. ५१, ४; ६. ६६, ७; १०. २०, ९.
यामः ३. ३३, ६.
यामऽकोशाः ३. ३०, १५.
यामन् १. ३३, २; ३७, ३; ८५, १; ११२, १; ११६, १३; १३१, ७; १६६, १; १८१, ७; २. ३६, २; ३. २, १४; २९, ६; ३०, १३; ४. २४, २; ५. ४४, ४; ५२, २; ५८, ७; ७३, ९²; ६. १५, ५; ३८, १; ४; ७. ५८, २; ६५, १; ६६, ५; ८५, १; ८. २२, १४; १०. ३, ४; ४६, १०; ७७, ८; ७८, ६; ९४, १३; १२७, ४.
यामनः ५. ५७, ३.
यामनि १. २५, २०; १३८, २; १६८, ५; ३. ५४, १४; ४. २७, ४; ५. ५३, १६; ७. ३२, २६; ९. ४५, ४; १०. ६४, १; ७७, ४; ८०, ५; ९२, १३.
यामनिऽयामनि ९. ६७, १०.
यामऽभिः १. ३७, ११; ५. ६६, ५; ८१, ५.
यामं ७. ५६, ६; ६९, २; ८. ७, २; ४; १४; ९६, १.
यामऽश्रुतेभिः ५. ५२, १५.
यामऽहूतमा ५. ७३, ९; ८. ७३, ६.
यामऽहूतिषु ५. ६१, १५; ८. ८, १८
यामऽहूतौ १०. ११७, ३.
यामात् ३. ५३, १९.
यामाय १. ३७, ७; ३९, ६; ८. ७, ५.
यामासः ५. ३, १२; १०. ३, ४.
यामि १. ५८, ७; ३. ५४, ३; ८. ३, ११; ५३, ८; ६१, ६; १०. ४७, ८.
यामि १. २४, ११; २. १६, ७; ५. ५४, १५; ७३, २; ६. ५१, ४; ८. ३, ९; २७, १; ७३, ६; १०. ४९, ७; ८७, १; ११९, १३.
यामे ५. ५४, ५.
यामेन ५. ५३, १२.
यामेभिः ८. ७, ७; ९. ६७, ७.
यामेषु १. ३७, ८; ४८, ४; ८७, ३; ४. ३२, २३; २४; ५. ५६, ७; ७३, ७; ८. २०, ५.
यायां ५. ६४, ३.
यावत् १. ३३, १२; १०८, २; ३. १८, ३; ७. ७९, ४; ९१, ४³; १०. ११४, ८².
यावतः ७. ३२, १८.
यावत्ऽमात्रं १०. ८८, १९.
यावा ७. १, ५.
यावीः ८. ७९, ४.
यावीः १. १२९, ३.
याशूनां १. १२६, ६.
यासत् १. ७१, ६; ६. १६, २८; ८. १, ८.
यासत् ४. २०, १; ५. ४०, ४; ६. ६६, ५.
यासां १. १३३, ४; ७. ४९, ३; १०. २२, १३; १६९, २; ३.
यासि १. १२, ४; ४४, १२; ७४, ७; ४. १६, ११; ६. २३, १; ७. ९२, ३; ८. ९, १८; १०. ९१, ११; ११२, २; १४२, ४.
यासि १. १६५, ३; २. १, ६; ३. १, १७; ४. १३, ४; ५. ८१, ४; ६. १२, ६; ५८, ३; ९. ८२, २; ८३, ५; ८७, ९; १००, ८; १०. ४, ३; ३२, २; ३७, ३; ७३, ४; ७५, २.
यासिषत् १. १७४, ५.
यासिष्टं १. ११९, ४; ७. ४०, ५; ६७, १०.
यासिष्टं ८. २२, १७.
यासिसीष्ठाः ४. १, ४.
यासीष्ट १. १६५, १५; १६६, १५; १६७, ११; १६८, १०.
यासु १. १४१, ५; २. ११, ३; १३, १; ४. ५१, ७; ५. ४४, १; ८; ७. ४९, ४⁴; ६१, ५; १०. ९१, १२.
याहि १. १२९, ९; २. ११, १७; ३. ३५, १; ४५, १; ४. ४, १; २९, १; ४८, १; ६. १८, ११; ३१, ५; ७. ९, ५; १४, ३; २३, ४; ८. २३, ६; २६, २३; ४६, २५; ९३, ३१; १०१, ९.
याहि १. २, १; ३, ४–६; १४, १; ३१, १७; ८२, ३; ५; ६; १०१, ८; १२९, ९; १३०, १; १३४, १; १३५, १; २²; ३; ७; १६३, ६; १७७, १–५; २. १८, ४–७; ३. ४, ११; ६, ९; २९, १६; ३०, २; ३१, १९; ४१, १; ८; ४३, १–३; ५३, ५; ६; ६०, ७; ४. १६, १०; ४७, १; ५. ४, ५; ३५, ५; ४०, १; ५१, ५; ८; ६. १६, १०; ४४; २१, ११; २२, ११; ३२, ४; ४०, ३; ४; ४१, १; ४; ५; ७. ७, २; ११, १; २४, १; ३; ४; २८, १; २९, १; २; ३०, १; ३२, ४; ९०, १; ८. १, २३; २, १९; २८²; ६, ३६; १३, ११; १७, १; ४; २१, ३; ३३, १३; ३४, ७; १०; १३; ६०, १; ६२, ४; ६५, १; ९२, १०; १०३, १४; ९. १४, ८; ६४, १५; १८; ६६, ७; ९७, ६; १०३, ५; १०६, ७; १०९, १८; १०. १, ७; १०, ८; १५, ९; ४४, २; ५; ८७, ३; ८९, १६; ९८, ९; १०४, १; ६; ११०, ३; ११२, २; ४; १४२, ७; १७२, १; २; १७९, २.
युः ८. १८, १३.
युक्तऽअश्वं ५. ४१, ५.
युक्तः १. ६९, ४; ८२, ५; १५९, ३; ७. ६३, २; ६९, २; ८. ५८, १; १०. २७, ९; ५१, ७; १०२, ६.
युक्तऽग्रावा ३. ४, ९; ५. ३७, २.
युक्तऽग्राव्णः २. १२, ६.
युक्त ८. २५, २२; १०. १०, १३.
युक्तस्य १०. १०२, ६.
युक्ता १. ८४, ३; ११६, १८; १६४, ९; ५. २७, २; ८. ९४, १; १०. ९३, १३.
युक्ताः १. १६४, १४; १९; ३. ३०, २; ५३, ४; ५५, १८; ६. ४७, १८; ७. २८, १; ७९, २; ८. १, २४; ५७, १; १०. ९४, ६; ७.
युक्तान् १. २३, १५; १२६, ५; ५. ३१, १०.
युक्तानां ४. ३२, १७.

युक्ताभ्यां ६. २३, १.
युक्तासः १. ११८, ४; ४. ४८, ४; ६. ३७, १; ७. ९०, ५; १०. ११४, १०.
युक्तेन ५. २७, ३.
युक्तैः १०. ११२, ४.
युक्तौ १०. २७, २०.
युक्त्वा १. १६१, ७; १७७, १; ३; ५. ४०, ४.
युक्त्वाय १०. ९३, १४.
युक्ष्व १. १०, ३; १४, १२; ८१, ३; ९२, १५; ६. १६, ४३; ८. ३, १७; २६, २०; ७५, १; १०. ४, ६; ११, ९.
युगं ३. ५३, १७; १०. ६०, ८; ७२, ९.
युगस्य ८. ९१, ७.
युगा १. १४४, ४; १८४, ३; २. २, २; ५. ५२, ४; ७३, ३; ६. १६, २३; ८. ४६, १२; ६२, ९; ९. १२, ७; १०. २७, १९; १०१, ३; ४; १४०, ६.
युगाऽइव २. ३९, ४.
युगानि १. ९२, ११; १०३, ४; ११५, २; १२४, २; ३. ३३, ८; ७. ७०, ४; १०. १०, १०.
युगाय ७. ८७, ४.
युगे १. १५८, ६; १६६, १३; १०. ७२, १–३.
युगेऽयुगे १. १३९, ८; ३. २६, ३; ६. ८, ५; १५, ८; ३६, ५; १०. ९४, १२.
युगेषु ७. ९, ४.
युंक्त १. १२४, ११.
युंक्ते १. ८४, १६; १३४, ३.
युंक्ष्व ७. ४२, २.
युंग्ध्वं ५. ५६, ६[२].
युच्छतः १. २५, ६.
युच्छंति ५. ५४, १३.
युच्छंतु ८. ३९, २.
युच्छसि ८. ५२, ७.
युजः ४. ३२, ६; ८. ८३, २.
युजः १. १०, ९; ९. ७, ३.
युजत ५. ५२, ८.
युजंत ६. ६६, ६; ८. २०, ४.
युजं १. ७, ५; ३३, १०; १२९, ४[२]; २. २५, १–५; ४. ३७, ५; ५. २०, १; ३०, ८; ३४, ८; ६. ४५, १९; ८. ६२, ६; ७७, ७; ९. ६५, १२; १०. ४२, ४; ८९, ८; ९२, ७.
युजा १. ८, ४; २३, ९; ३९, ४; १०२, ४; २. २३, १०; ४. २८, १; २; ६. ४४, २२; ५६, २; ७. १, १३; ३१, ६; ३२, २०; ४३, ४; ४८, २; ९५, ४; ८. १७, ३; २१, ११; ६३, ११; ६८, ९; ९२, ३१; ३२; ९६, १५; ९. ११, ९; १४, ४; १०. ३३, ९; ५५, ८; ६२, ७; ८३, १; ३; ८४, ४; १०२, १२.
युजाऽइव २. २४, १२.
युजानः २. १८, ५; ३. ५७, ४; ४. २, ३; ६. ३४, २; ३९, २; ४७, १९; ७. ६९, ५; ७०, २; ८. १३, २७; ५०, ७; ९. ६४, १९; ८६, ३७; ९७, २८; १०. २२, ४.
युजानं १. ६५, १.
युजाना ५. ८०, ३; ७. ७५, ४.
युजानाः १. १६५, ५; ३. ४३, ६; ६. २९, २; ४४, १९.
युजे ७. २३, ३; ८. ४१, ६; १०. १३, १.
युज्महे १. १६५, ५.
युज्यः १. २२, १९; २. २८, १०; ७. २२, २.
युज्यते ४. ४५, १.
युज्यते ५. १, ३; ९. ७२, १.
युज्यध्वं १०. १७५, १.
युज्यंते १. १४०, ४.
युज्यं १. ५२, ७; १५६, २; ४. २५, २; ६. ५२, १०; ७. ३६, ७; ८. ४, १२; ४६, १९.
युज्यमानं २. ४०, ३; ७. ७८, ४.
युज्यमाना ३. ३५, १.
युज्यसे १. २८, ५.
युज्या ८. ९०, २.
युज्यातां ७. ४२, १.
युज्याभिः ७. ३७, ५.
युज्याय २. २८, ३; ७. १९, ९; ८. ४, १५; ९. ६६, १८; ८८, १.
युज्याव ८. ६२, ११.
युज्यासः १०. ९९, ४.
युज्येन ६. २१, ७.
युज्येभिः १. १४५, ४; १६५, ७; ६. ३, ८; ७. ३९, ६.
युंजते १. ४८, ४; ८७, ३; १३९, ४; २. ३४, ८; ५. ८१, १.
युंजते १. १८६, ९; ५. ४३, ४; ६३, ५; ८१, १; १०. ९४, १२.
युंजंति १. ६, १; २; ८. ९८, ९; १०. १०२, १०.
युंजंति १. १६४, २; ९. ६२, १७; ८९, ४; १०. १०१, ४; १६४, २.
युंजं १०. १०२, ९.
युंजां १. १६२, २१.
युंजाथां १. ४६, ७; ८. २२, ९; ७३, १; ८५, ७.
युंजाथां १. १८३, १; २. ३७, ५; ४. ४५, ३.
युंजाथे इति १. १५७, २.
युंजाथे इति १. १५१, ४; ५. ७४, ३.
युंजे ३. १, १.
युतऽद्वेषसः १. ५३, ४.
युतऽकारेणं १०. १०३, २.
युतऽसु १. ९१, २१; १४०, १०; २. १७, २; ७ ८२, ४; ९. ८९, ३; १०. १०३, ७.
युद्धानि १०. ५४, २.
युधः १०. १०३, २; ३.
युधः ८. २७, १७.
युधं १. ५३, ७.
युधये ५. ३०, ४; ९; १०. २७, २; ३८, ३; ४८, ६; ८४, ४; ११३, ३.
युधा १. ५३, ७; ५९, ५; १७४, ४; २. २२, २; ३. ३४, ७; ४. १७, १०; ५. २५, ६; ५२, ६; ७. १८, ७; २१, ६; ९२, ४; ९८, ३; ८. १६, १०; २१, १३; ४५, ३; १०. ४९, ९; ५५, ८; ६०, ३; १०३, ४.
युधाऽइव १. १६६, १.
युधि १. ८, ३; २. २४, ९; ६. ४६, ११; ८. ४५, २१.

युधे १. ६१, १३.
युधेन्यानि १०. १२०, ५.
युध्म ८. १, ७.
युध्मः १. ५५, २; ५; २. २१, ३; ६. १८, २; ७. २०, ३.
युध्मं ८. ९२, ८.
युध्मस्य ३. ४६, १.
युध्माः ४. २४, ४.
युध्य १. ९१, २३; ६. ३१, ३.
युध्यंत ८. ९६, १४.
युध्यंतः १. ५२, ५; १४; ३. ५५, ८; ८. ७, २४.
युध्यंते ४. ३०, ४.
युध्यन् १. ६३, ७; ५. ३३, ४; ६. २६, २; ९. ७०, १०.
युध्यंतः ६. ३३, ४.
युध्यंतःऽइव ८. ४७, ८.
युध्यंतं १. ३३, १४; ६. २६, ४.
युध्यंते १०. १५४, ३.
युध्यंते ८. २, १२.
युध्यमानाः २. १२, ९; ४. २५, ८; १०. २५, ९.
युध्यामधिं ७. १८, २४.
युध्यै ४. १८, २.
युध्वा ९. ६६, १६; ८८, ५; १०. ७५, ४.
युनक्त १०. १०१, ३.
युनक्त १०. १०१, १०.
युनक्षि १०. ६०, ६.
युनजंत ७. ३६, ४.
युनजत १०. २७, ९.
युनजंते ७. २७, १.
युनजन् ६. ६७, ११; १०. ५१, ४.
युनज्मि १. ८२, ६.
युनज्मि ३. ३५, २; ४; ५०, २; ७. १९, ६.
युयवत् ६. ४४, १६.
युयवन् ७. ३८, ७.
युयुजानः ४. २, २; ४५, ६; ५. ४०, ८; ६. ५९, ५.
युयुजानसप्ती इति युयुजानऽसप्ती ६. ६२, ४.
युयुजे १. १६१, ६; १०. ३४, ११; १०५, ३.
युयुजे ८. ४, ११; १०. ७५, ९; ७९, ७.
युयुज्म ८. ६१, १२.
युयुत्रे ५. ५३, १; ६. २५, ३.
युयुत्रे १. ४६, ८; १०. ३३, १.
युयुतं ६. ५९, ८; ७. ७१, २; ८. ९, १.
युयुत्सन् १०. ४८, १०.
युयुत्संतं ५. ३२, ५.
युयुधयः १. ८५, ८; १०. ११५, ४.
युयुधाते इति १. ३२, १३.
युयुधिःऽइव १०. १४९, ४.
युयुधुः ४. ३०, ३; ५. ५९, ५; ७. ८३, ७.
युयुयातां ८. १८, ८.
युयुविः ५. ५०, ३.
युयूपतः १. १४४, ३; ६. ६२, १.
युयूपन् ४. १६, ११.
युयोजते ८. ७०, ७^{2}.
युयोत ३. ५४, १८; ७. ३४, १३; ५६, ९; ८. १८, ११.
युयोत १. ३९, ८; २. २९, २; ७. ५८, ६; ८. ७१, ८; १०. ७७, ६; १००, ९.
युयोतन ८. १८, १०.
युयोतन ५. ८७, ८; १०. ६३ १२.
युयोतं ७. ६८, ५; ७१, १.
युयोति १. ९२, ११.
युयोतु ५. ५०, ३; ६. ४७, १३.
युयोथाः २. ३३, १.
युयोध ६. २५, ५.
युयोधि १. १८९, १; २. ६, ४; ८. ११, ३.
युयोधि १. १८९, ३; २. ३३, ३; ६. ४८, १०; ९. १०४, ६.
युयोप १. १०४, ४.
युयोपिम ७. ८९, ५.
युव ९. १०८, ९.
युवंऽजानिः ८. २, १९.
युवत् १. १११, १; १०. ३९, ८.
युवत् १. १०९, १.
युवतयः १. ९५, २; २. ३५, ४; ११; ३. १, ६; ५४, १४; ५५, १६; ५. २, ४; ६. ६७, ७; १०. ३०, ६.
युवतिं १०. ४२, ५.
युवतिः १. ११३, ७; ११८, ५; १२३, २; १०; १२४, ११; ३. ६१, १; ४. १८, ८; ५. २, १; ४७, १; ६१, ९; ८०, ६; ७. १, ६; ७७, १; ८०, २; १०. १८, १०; ७५, ८; ११४, ३; १८३, २.
युवतिऽभिः ९. ८६, १६; १०. ३०, ५.
युवतिं १. १६७, ६; १०. ४, ४; १७८, ३.
युवती इति १. ६२, ८; १८५, ५; ३. ५४, ७.
युवतीः ४. १९, ७.
युवतेः ५. ३२, १०; ७. ४, २; १०. ११५, २.
युवते १. १०५, २; ५. २, २; ९. ७७, २.
युवत्याः १०. ४०, ११.
युवत्यां १०. ६१, ६.
युवत्योः ६. ४९, २; १०. ३, ७.
युवद्रिक् ४. ४३, ७.
युवऽधिता ६. ६७, ९.
युवन् १. १४१, १०.
युवंत ८. ७१, ४.
युवन्यून् ५. ४२, १५.
युवंऽभिः ३. ३१, ७.
युवंऽभ्यः १. २७, १३.
युवऽभ्यां १. १०८, २; १०९, २; ११७, २५; ७. ६०, १२; ६८, ४; ७०, ६.
युवं १. १५, ६; ३४, ३–५; ४७, ५; ८९, ४; ९२, १७; ९३, ५^{2}; ११; ११२, ३; ११६, ७; १४; ११७, ७; ८; १३; १४; २०; ११८, ७^{2}; ८; ९; ११९, ४; ६^{2}; ७; ९; १०; १२०, ४; ७^{2}; १२२, ३; १३२, ६; १३५, ५^{2}; १५१, ४; ६; १५२, १; १५७, ४; ५^{3}; ६; १८०, २–४; १८२, ५; २. ३०, ६; ३. ३८, ९; ५४, १६; ५८, ७; ४. १५, १०; २८, ५; ४१, ४; ४२, १०; ४३, ७; ४४, २; ५. ६३, १; ६४, ६; ६५, ६; ६६, ४; ७५, ३; ८; ७८,

६; ६. ५०, १०; ५९, १; २; ६०, ३; ६३, ६; ६७, ८; ६८, ६; ७२, १[३]; ५[२]; ७४, ३; ७. ६९, ७; ७१, ५; ७४, २; ८२, १; ८३, ५; ८५, २; ९७, १०; १०४, ५; ८. ५, १४; २३; ३६; ८, १; १०; १६; १९; ९, १; २६, २; ५; ४०, १; ५७, १; ७३, ७; ८५, १; ९; ८६, २; ३; ९. १९, २; १०. २४, ४; ६; ३९, ३; ४; ७[२]; ८[२]; ९[२]; १०; १३; ४०, ४; ६; ७[३]; ८[४]; ६५, १२; १३१, ४; १३२, ७; १४३, ५.

युवमानः १. ५८, २.

युवस्युः ६. ६३, ३.

युवस्यूः ४. ४१, ८.

युवस्यूनि ७. ७०, ७.

युवशा १. १६१, ३; ७.

युवशाऽइव ८. ३५, ५.

युवसे ६. ४७, १४; ६०, २; १०. १९१, १.

युवस्व ४. ४८, ५; ८. २६, २०.

युवस्व ६. ६, ७; ३९, १; ७. ५, ९; ९२, ३.

युवा १. ११, ४; १२, ६; ८७, ४; १४४, ४; १५५, ६; २. ४, ५; २०, ३; ३. ८, ४; २३, १; ४. १, १२; ५. १, ६; ४४, ३; ४५, ९; ६०, ५; ६१, १३; ७४, ५; ६. ४५, १; ७१, १; ७. २०, १; ८. २१, २; २९, १; ४५, १; ६४, ७; ९. १४, ५; १०. ४०, ११; ४६, ३.

युवाकवः १. ३, ३.

युवाकु १. १७, ४[२]; १२०, ९.

युवाकुः १. १२०, ३; ३. ५८, ९; ७. ६०, ३; ६७, ४; ६८, ७.

युवाकोः ७. ६८, १.

युवाऽदत्तस्य ८. २६, १२.

युवानः १. ६४, ३; १५२, ५; १६५, २; १६७, ६; ३. ५४, १०; ५. ५७, ८; ८. २०, १७; १८.

युवानः १. १८६, १; ५. ५८, ३; ६. ४९, ११.

युवानं १. ७१, ८; ११७, १३; ११८, ६; २. १६, १; ३३, ११; ३५, ४; ३. ३२, ७; ६. ५, १; १९, २; ८. ४४, २६; ९. ९, ५; ६७, २९; १०. ३२, ८; ३९, ४; ५५, ५; ९२, १४.

युवाना १. २०, ४; ११०, ८; ४. ३३, ३; ३५, ५; ३६, ३; ६. ६२, ४.

युवाना १. ११७, १४; ३. ५८, ७; ७. ६२, ५; ६७, १०.

युवाऽनीतस्य ८. २६, १२.

युवाभ्यां १. १०९, ४; २. ४०, ५; ५. ६४, ४; ८. ५, ३; १८; २६, १६; १०१, ८.

युवां १. ४७, ४; १०९, ५; ११७, १९; ११९, ५; १३९, ३[२]; १५१, ८; १८०, ८; १८१, ९; १८३, ५; २. ४१, १९; ४. ४१, ७; ४७, २; ५. ७३, ९; ६. ६०, ७; ७. ७४, ४; ८२, ४[२]; ८३, १; ६; ८. ५, १७; ५७, २; १०. ३९, ३; ४०, ४; ५.

युवामहे ६. ५७, ६.

युवाऽयवः १. १३५, ६.

युवाऽयुजः १. ११९, ५.

युवाऽवते ३. ६२, १.

युवासे ६. ३५, ३.

युवे ८. १९, ३३.

युवेथे इति १. १८०, ६.

युवोः १. ३४, १; १०; ४६, १४; ११२, २; ११७, १३; ११९, ३; ५; ८; १३९, २; ३; १५२, १; १८०, १; २. २४, १२; ३. १२, ८; ५४, ३; ५८, २; ६; ४. ४४, २; ५. ७३, ६; ६. ५९, ९; ६७, ११; ६८, १०; ७०, ३; ७. ६९, ४; ७२, २; ८२, ८; ८४, २; ९३, ८; ८. २२, ४; २६, १; १०. ४०, ६; ७[२]; ६१, २५; १३२, २; ६.

युष्मत् ५. ५८, ४; ७. ६०, १०; ९५, ५.

युष्मभ्यं १. ८८, ३; १७१, ४.

युष्मऽयंतीः २. ३९, ७.

युष्माऽइषितः १. ३९, ८.

युष्माऽऊतः ७. ५८, ४[३].

युष्माकं ७. ५९, ९; १०.

युष्माकं १. ३९, २; ४; ११०, ७; १२४, १३; २. २७, ५; ५. ५३, ५; ८. १८, १७; १०. ७७, ४; ८२, ७; १२६, ४.

युष्माकाभिः १. ३९, ८.

युष्माकेन १. १६६, १४.

युष्माऽदत्तस्य ५. ५४, १३; ८. ४७, ६.

युष्मान् १. १६१, १४; ४. २, ३; ८. ७, ६[२].

युष्माऽनीतः २. २७, ११.

युष्माभिः ८. ६३, १०.

युष्माऽवत्ऽसु २. २९, ४.

युष्मे इति ४. १०, ८; ३७, ३; ६. १८, ५; ८. १८, १९; ४७, ८; ६८, १९.

यूथं ४. ३८, ५; ५. २, ४; ८. ४६, ३०.

यूथस्य ५. ४१, १९; १०. ३२, ४.

यूथा १. ८१, ७; ८. ६१, ८; ९. ७१, ९; ७६, ५; ९६, २०.

यूथाऽइव १. ७, ८; ४. २, १८; ५. ३१, १; ६. १९, ३; २९, ५; ४९, १२; ७. ६०, ३; ८. २५, ७.

यूथानि ८. ४, २०.

यूथे १. ५८, ५; १६४, १७; ३. ५५, १७; ९. ७७, ५; ११०, ७.

यूथेन १. १०, २.

यूथेषु १०. ८६, १५.

यूथ्यः ९. १५, ४.

यूथ्या १०. २३, ४.

यूथ्याः ८. ५६, ४.

यूनः १. ११२, २१; ३. ४६, १; ६. ५१, ४; ८. २०, १९.

यूना ९. ६८, ५.

यूने १. ५३, १०; ६३, ३; ९१, ७; १७४, २; ५. ३६, ६; १०. ३०, ६.

यूपः १. ५१, १४.

यूपऽव्राहाः १. १६२, ६.

यूपऽव्रस्काः १. १६२, ६.

यूपाऽइव ४. ३३, ३.

यूपात् ५. २, ७.

यूयं १. १५, २; ३८, ४; ८६, ९; १६६, ६; १७१, २; २. २८, ३;

२९, २^{३}; ३; ४; **४.** ३६, ८; ३७, ६; ५१, ५; **५.** ५४, १४^{४}; ५५, ५; १०; ५८, ४; ५९, ४; ६१, १५; ८७, ९; **६.** २८, ६; ५०, ७; ५१, ६; १५; **७.** १, २०; २५; ३७, २; ६६, १२; **८.** १९, ३५; २०, १६; २३; ४७, ८^{२}; ६७, १९; ८३, ३; **९.** ६९, ८; ९८, १२; **१०.** ६४, १२; ७७, ५; ६; ९७, २; ९; १२६, २; ४; १३६, ३.

यूयाः **७.** १०४, १५.

यूयोत् **१०.** ९५, १२.

यूष्णः **१.** १६२, १३.

ये **१.** ७, ७; ८, ६; १४, ६; ८^{२}; १९, ३–८; २०, २; २४, ६; १०; २५, ९; ३३, १०; ३४, ९; ३५, ११; ३७, २; ४८, ३; ४; ११; १४; ५१, ५; ८; ५३, ११; ५४, ८; ५५, ७; ५७, ४; ६०, २; ६७, ४; ६८, ५; ७२, ९; ७७, ४; ८३, ४; ८५, १; ४; ९४, ९; १०१, १०; १०५, ५; ९; १०; ११०, ६; ११३, ११^{२}; ११८, ४; १२४, १२; १२६, ५; १३५, ९^{२}; १३९, ११; १४१, १३; १४७, ३; १६१, ५; १६२, ६^{३}; १२^{३}; १६४, ३; १९^{२}; २३; ३९; ४५; १६६, ४; ११; १६८, २; ३; १६९, ५; ७; १७३, ७; १७४, १; ६; १७७, २; १७९, २; १९०, ५; ६; १९१, ७^{३}; **२.** १, १६; २, १३; ११, १३; १४; १६; १९; २३, १४; १६; २४, ६; २७, १०^{२}; २८, ७; ४१, १; **३.** ६, ८^{३}; ७, १; ८, ७; १६, २; २२, ३; २४, ४; ३२, ३^{२}; ४; ३५, ९; ३९, ४; ४३, ६; ४७, ३; ४^{४}; ६१, २; **४.** ५, ४; ६, १०; ८, ५^{२}; ६; १६, ६; १८, ४; २३, ५; ३२, ३; ३३, १; ३; ८^{२}; १०^{२}; ३४, ९^{७}; १०^{२}; ३५, ८; ४५, ४; ५०, २; ५४, ६; ५५, २; **५.** २, ५; ६, ७; ८; १०, ३; ४; १५, २; १६, ५^{२}; १८, ४; ५; २०, २; ३१, ५; १३; ३२, १२; ३३, ५; ३८, ३; ४१, २; ५; ९; १३; ४२, ८; ९; १२; ४९, ५^{२}; ५०, २; ५२, १; ४; ५; ७^{२}; १३; १६; ५३, ३; ४^{२}; ५६, २; ४; ५८, १–३; ५९, २; ७; ६०, २; ६१, १; ११; ७९, ४; ६; ८७, २^{२}; ३; **६.** ६, ४; १०, ५; १६, ४३; २१, ५; ११^{२}; १२; २५, ३; ७; २७, १; ३६, १; ४६, १०; १४; ४८, ८; ५०, २; ५२, ९; १३^{३}; १५; ६३, ८; ६६, २–५; ९; ६७, ९; **७.** १, ९; १०; २, २; ७, ६^{३}; १६, ७; १०; १८, १२; २१; १९, ९; २०, १०; २२, ९^{२}; २५, २; ३०, ४; ३२, १५; १७; ३४, २४; ३५, १४; १५; ३८, ५; ४२, २; ५६, १६; ५७, १; ७; ५८, २; ६२, ४; ६६, ५; ६; १०; ११; १३; ६७, ८; ९^{२}; ७४, ४; ६; ८७, ३; ९०, ६; ९१, १; ९२, ४; ९६, ५; १०४, ९^{२}; १८^{२}; **८.** १, ९^{३}; २, ३९; ६, १२^{२}; १८^{२}; ७, १६; ९, ३; १३, २८; १८, २२; १९, १७; १८; २०, १८^{२}; २०; २८, १; ३०, २; ४; ३४, १७; ४५, १; ४६, १८; ४९, ३; ८; ५३, ३^{२}; ६; ५७, ३; ६७, १३; ९३, ६^{२}; ९४, ९; ११; ९६, ७; ९७, १; १०३, १३; **९.** ४१, १; ६१, ५; ६५, २२^{३}; २३^{३}; ७३, ५; ७५, ५; ७७, ३; ८६, ४; ९१, ४; ५; ९७, २०; २८; ११४, ३; **१०.** २, १; १०, ८; १३, १; १४, ३; १०; १५, १; २^{४}; ३; ८–१०; १३^{२}; १४^{२}; १९, ७; २०, ८; २७, ६; २८, ११; १२; २९, ५^{२}; ३२, २; ३६, १०; १३; ४०, १०; ४४, ६; ७; ४८, ६; ५०, ३^{२}; ७; ५३, ८; ५५, ७; ६१, १०; १४; २७^{२}; ६२, १–३; ६; ६३, १^{२}; २^{२}; ५; ८; ६४, ६; ६५, ३; ९^{२}; १५; ६६, १; २; ७२, ८; ७३, ३; ७४, १^{२}; ३; ४^{२}; ७६, ८; ७७, ३; ७; ७८, २–५; ८२, ४; ८५, १७; ३१; ३२; ८९, ८; ९; १५; ९०, ७; ८; १०; ९२, ७; ९३, १४; ९६, २; १०७, २; ४; ९; १०८, ७; १०९, ४; ११५, ७; ११६, ९; १२८, ९; १३०, १; ६; १३१, २; १४७, ३; १४८, ३; १५४, २^{३}; ३^{३}; ४; ५; १७६, १; १८२, ३.

ये इति **१.** १५९, १; १८५, ६; ७; **९.** ६६, २.

येजे **६.** ३६, २.

येतिरे **१.** ६४, ४; ८५, ८; **५.** ५९, २; **८.** २०, १२; **१०.** ७७, २.

येन **१.** ८, २; ३४, ९; ४२, ५; ४७, ९; ५०, ६; ५६, ३; ६१, ६; ६२, २; ६३, २; ७२, ८; ८०, २; ९२, १३; ११७, २; १६०, ५; १६४, २९; ४९; १६६, १४; १७१, ५; १८२, ५; १८३, १; ३; १८६, ५; **२.** ११, १८; १२, ४; १७, ६; ७; २४, १०; ३०, ५; **३.** २२, २; २९, ९; ३१, ९; ६०, २; ६२, १; **४.** ९, ८; ३६, ९; ४३, ६; ४५, ७; ५१, ४; ५३, १; **५.** ४५, ७; ५३, १३; ५४, १५; ७७, ३; ८७, ५; **६.** १६, ४८; १७, १०; १९, ७; ८; २७, ४; ४४, ३; ४६, ५; ४९, १५; ५१, १६; **७.** १, २४; २२, २; ५६, २४; ६९, २; १०४, ४; **८.** ३, ९^{२}; १०; ५, ३९; ६, ११; ७, १८^{२}; ९, ४; १२, १; २^{२}; ३; ४; १३, २१; १५, ५; १७, १०; १९, १६^{२}; २०; २४, २५; २७, २२; ४०, १; ६०, १२; ७६, ४; ८९, १; **९.** ७४, ५; ९७, ३९; ५१; १०१, ९; १०८, ४^{३}; १४; १०९, १४; **१०.** ३७, ४; ४१, २; ४४, ९; ५१, १; ५२, १; ५३, ४; ७; ९; १०; ५५, २^{२}; ४; ८५, २४; ८७, १२; १०२, ९; ११४, ७; ११६, ३^{२}; १२१, ५^{३};

१२६, २; १५९, ४; १७०, ४; १७४, १.

येभिः १. १०९, ७; १२१, ६; १७४, ३; २. ३७, ३; ३. ३, १०; ३२, ४; ३६, २; ६. १७, ५; ७. १, ७; ८. ५, ८; २२, ७; ३८, ५; ४९, ८^2; ५०, ८^2; ६२, ४; ९. ७०, ३; ७९, २; १०. २, ४; ५४, ४; ५५, ७; ८५, २३; ९२, ५; ९; १५; ११२, २; ११३, १०.

येभ्यः १०. ६३, ३; ७; १५४, १.

येम ८. २७, २०.

येमतुः १. ११९, ५; ५. ६१, ९.

येमथुः ८. २५, ६.

येमथुः १. ३०, १९; ५. ७३, ३.

येमाते इति ४. ४८, ३.

येमानः ४. २३, १०; ४४, ३; ९. ७५, ३; १०७, १६; १०९, ८; १८.

येमानं ४. १, १५.

येमिम ८. २१, ४.

येमिरे १. १३५, १; ८. ७, ५.

येमिरे १. १०, १; ३. ५९, ८; ६०, ६; ८. ३, ६; ४, ५; ७, ३४; १२, २८; ४३, १८; ८९, २; ९८, ३; ९. ८६, ३०; १०. ५६, ५.

येमुः ३. ३८, ३; ७. ६६, १०.

येमुः ४. २, १४; ६. २१, ६.

येमे ५. ३२, १०; १०. ५, ५; ४०, १४.

येषंती ३. ५३, २२.

येषं २. २७, १६.

येषां १. ३७, ८; ३. ७, ५; ९, ३; ५. २, ५; १०, ४; १८, ३; ६१, १२; ८७, ३; ७; ६. ६८, ७; ७. १६, ८; २९, ४; ४३, १; ८. १६, ५; २०, १३; २३, ३; ४५, १; ५४, २; १०. ४४, ७; ९३, १३.

येषु १. ५१, १२; १२२, १२; १६७, ३; २. ११, ३; १५; ५. १८, ४; ३१, १३; ६४, ६; ६. १९, १२; ५०, ५; ६६, ५; ७. ८५, २; ९. ७५, १; १०. ३२, ५; ६१, ३; १४८, ४.

येष्ठः ५. ७४, ८.

येष्ठां ५. ४१, ३.

येष्ठाः ७. ५६, ६.

यो इति ५. ७९, ३.

योः १. ७४, ७; ९३, ७; १०६, ५; ११४, २; १८९, २; २. ३३, १३; ३. १७, ३; १८, ४; ४. १२, ५; ५. ४७, ७; ५३, १४; ६९, ३; ६. ५०, ७; ७. ३५, १; ६९, ५; ८. ३९, ४; ७१, १५; १०. ९, ४; १५, ४; ३७, ११; १०५, ३; १७६, ३; १८२, १.

योक्त्रं ५. ३३, २.

योक्त्राणि ३. ३३, १३.

योगः १. ३४, ९.

योगऽक्षेमं १०. १६६, ५.

योगे १. १८, ७; १०. ११४, ९.

योगान् २. ८, १.

योगे १. ५, ३; ३. २७, ११; ४. २४, ४; ५. ३७, ५; ४३, ५; ७. ५४, ३; ६७, ८; ८६, ८; ८. ५८, ३; १०. ३०, ११; ३५, ९; ३९, १२; ८९, १०.

योगेऽयोगे १. ३०, ७.

योग्याः ७. ७०, ४; १०. ५३, ११.

योग्याभिः ३. ६, ६.

योजं १. ८२, १–५.

योजते ७. १६, २.

योजनं १. ८८, ५; १९१, १०–१३; ५. ५४, ५; ८. ७२, ६; ९. ७, १.

योजना १. ३५, ८; २. १६, ३; ८. ९०, ३; ९. १०२, ३; १०. ८६, २०.

योजनानि १. १२३, ८; १०. ७८, ७.

योजनेन १. ९२, ३.

योजनेभिः ६. ६२, ६.

योजनेषु १. १६४, ९.

योजं २. १८, ३.

योजि २. १८, १.

योतवे ८. १८, ५.

योतवै ८. ७१, १५.

योतोः ६. १८, ११.

योरसि १. १३२, ४.

योधः १. १४३, ५; ६. २५, ५.

योधत् ६. ३९, २.

योधं ६. २६, ४.

योधय ३. ४६, २.

योधयाः ७. ९८, ४.

योधाः ३. ३९, ४; १०. ७८, ३.

योधानः १. १२१, ८.

योधि ५. ३, ९.

योधिषत् ८. ४५, ५.

योधिष्टं ६. ६०, २.

योधीः १०. १२०, ३.

योधीयान् १. १७३, ५.

योध्या ९. ९, ७.

योना १. ६५, २; १४४, ४; १६४, ३२; ३. ५४, ६; ४. १, १२; ८. ९, २१; ९. ६२, ८; १५; ७२, ६; ७३, १; ८६, ६; २५; १०. ६५, ८.

योनाऽइव १०. १०१, ११.

योनिः १. १०४, १; १६४, ३३; २. ३, ११; ३. २९, १०; ५३, ४; ४. ३, २; ५. ७८, ५; १०. १२५, ७.

योनिं १. ११३, १; १२४, ८; १४०, १; २. ३८, ८; ३. ५, ७; ३३, ४; ६२, १३; ४. ५०, २; ५. २१, ४^2; ४७, ३; ६७, २; ६. १५, १६; १६, ३५; ७. ४, ५; ७०, १; ९७, ४; ८. २९, २; ९. १, २; २, २; ८, ३; १९, ३; २५, २; ६; ३२, ४; ३७, २; ३८, ६; ४०, २; ६१, २१; ६२, ४; ६४, ११; १७; २०; २२; ६५, १९; ६६, १२; ७०, ७; ७१, ७; ८०, २; ८२, १; ९७, ४५; १०१, १४; १५; १०७, ४; १०. १७, ११^2; १८, ७; ३४, ११; ६५, ७; ६८, ४; ९१, ४; ९६, २; ९९, २; १०७, ९; १२३, २; १४८, ५; १६२, १; ४; १८४, १.

योनिषु १. १५, ४; २. ३६, ४; १०. ४०, ११; ६३, १५; १२३, ५.

योनेः २. ९, ३; ३५, १०.

योनौ १. ६३, ४; ६६, ३; ७९, ३; १०४, ७; १४४, २; १४९, २;

१७४, ४; १७८, २; ३. १, ७; ११; २९, ८; ६२, १८; ४. १, ११; १६, १०; १७, १४; ६. १६, ४१; ७. ३, ५; ९. १३, ९; २५, ३; २८, ३; ३९, ६; ९२, २; १०. ८, ३; १०, ७; ३१, ६; ४६, ६; ६१, ६; ७०, ६; ८५, २४; १०१, ३; १२३, ६.

यो॒न्यं ८. ४५, ३०.

यो॒पर्यं॑तः १०. १८, २.

यो॒प॒या॒म॒सि॒ १०. १३४, ७.

योर्युंवतीनां ८. ६९, २.

यो॒यु॒वे॒ १०. ९३, ९.

योषं॑णः १. १४१, २; ४. ५, ५; ९. १, ७; ६, ५; ३२, २; ३८, २; ५६, ३; ६८, ७.

योषं॑णा ८. ८, १०; ४६, ३३; १०. ११, २; ४०, ६.

यो॒षणा॑ ५. ५२, १४.

योषं॑णाः ३. ५६, ५.

योषं॑णां ३. ५२, ३; ६२, ८; ४. ३२, १६; ९. १०१, १४; १०. ३९, ७; १४.

योषं॑णासु ७. ९५, ३.

योषं॑णे॒ इ॒र्ति॑ ७. २, ६; १०. ११०, ६.

यो॒ष॒त् २. १८, ८; ३३, ९; ४. २, ९; ८. १, २७; ३१, १७.

यो॒ष॒ति॒ ८. ३१, १७; ३३, ९.

योषा॑ १. ९२, ११; १०१, ७; ११९, ५; १२३, ९; ११; १६७, ३; ३. ३३, १०; ३८, ८; ४८, २; ५. ७८, ४; ६. ७५, ४; ७. ६९, ४; ७५, ५; ७७, १; ९. ३२, ५; १०. १०, ४; २७, १२; ४०, २; ९; १२३, ५.

योषा॑ऽइव १. ४८, ५; ५. ८०, ६; ६. ७५, ३; ९. ४६, २; ९६, २४.

योषाः॑ ४. ५८, ८; १०. १६८, २.

योषा॑ १. ५६, १; ११५, २; ११७, २०; ४. २०, ५; ९. ९३, २; १०. ३, २; ५३, ११.

यो॒षि॑तं ९. ३८, ४.

योषे॒ इ॒र्ति॑ १. १०४, ३.

यौ १. २३, ५; ९२, १७; ११६, १; ६. ६७, ३; ७. ६८, ८; ८४, २; १०. १४, ११; ६६, ७.

यौ॒ः २. ३२, २.

यौ॒षु॒ः १०. २३, ७.

यौ॒ष्टं॒ ८. ८६, १; १०. ८५, ४२.

र

रं॒ह॒ते॒ ९. ९७, ९.

रंह॑माणः ९. ११०, ३.

रंह॑माणा ९. १००, ४.

रंह॑यः ९. ८६, ४७.

रं॒ह॒यं॑तः १. ८५, ५.

रं॒ह॒यं॒ते॒ ८. १९, ६.

रंहिः॑ १०. ९५, ३; १७८, ३.

रंह्यः॑ २. १८, १.

रंह्यौ॑ १. १४७, ४.

रंह्या॑ ४. १, ३[२]; ९. २, १; ६, ८; १०६, १३; १०. ९६, ४.

रक्षं॑ १. १८, ३; ३५, ११; ५४, ११; ९१, ८; १७४, १; ३. १, १५; ४. ३, १४; ६. ८, ७; १६, ३०; ७१, ३; ७. १५, ३; ८. ८४, ३; ९. २९, ५; ६१, ३०; १०. ४, ७.

र॒क्ष॒ १. ३१, १२; ९. ११४, ३; ४; १०. ५३, ६; ८७, ९; २०.

रक्षः॑ १. २१, ५; ८६, ९; १३३, ५; ३. ३०, १६; १७; ४. ३, १४; ६. १८, १०; ७. १०४, १; ४; १३; २२; २३; ८. ६०, २०; ९. ५३, १; ९७, १०; १०. ८७, १०; १४; ८९, १४; ११८, ७; १५२, ३.

र॒क्षः॒ऽत्वेनं॑ ८. १८, १३.

रक्षः॑ऽभ्यः ७. १०४, २५.

र॒क्षः॒ऽयुजे॑ ६. ६२, ८.

र॒क्षः॒ऽहत्या॑य ६. ४५, १८.

र॒क्षः॒ऽहनं॑ १. १२९, ११; २. २३, ३; १०. ८७, १.

र॒क्षः॒ऽहना॑ ७. ७३, ४.

र॒क्षः॒ऽहा १. १२९, ६; ७. ८, ६; ९. १, २; ३७, ३; ६७, २०; १०. ९७, ६; १०३, ४; १६२, १.

रक्ष॑णेभिः ४. ३, १४.

रक्षं॑त २. ३४, ९.

र॒क्ष॒त॒ १. १६६, ८.

र॒क्ष॒त॒ः १. १६०, २.

रक्षं॑तं १. १८५, २–८.

र॒क्ष॒तं॒ १. ९३, ८; ७. ५०, १.

रक्षं॑तात् ४. ५०, २.

र॒क्ष॒तां॑ १. १८५, १०; १०. ३६, २.

रक्षं॑ति २. २६, ४; ८. ४१, १.

र॒क्ष॒ति॒ १. १३६, ५; ३. ५, ६; ५३, १२; ४. ५३, ५; ९. ७३, ३; ८३, ४.

र॒क्ष॒तु॒ ६. ५४, ५; ७. १५, ३.

रक्षं॑ते ९. ६८, ४.

र॒क्ष॒ते॒ ४. ५३, ४; ७. ८३, ९.

रक्षं॑थ ८. ४७, १.

रक्षं॑तं ५. ४४, ७.

रक्षं॑ति १. ४१, १; १०. १०८, ७.

र॒क्षं॒ति॒ ३. ५१, ५.

र॒क्षं॒तु॒ ८. ४८, ५.

रक्षं॑ते ८. ६७, १३.

र॒क्षं॒ते॒ १. ६२, १०; ७२, ६; ९०, २; ३. ७, ७.

रक्षं॑माणः १. ३१, १२; ९. ८७, २.

रक्षं॑माणा १. ७१, ९; ५. ६२, ५; ७. ६१, ३.

रक्षं॑माणाः १. ७२, ५; १४६, ४; २. २७, ४; १०. ६८, १.

रक्षं॑माणासः १. ९६, ६.

रक्षं॑माणौ ५. ६९, १.

र॒क्षसः॑ १. ३५, १०; ३६, १५; ७६, ३; ७९, ६; १२९, ११; २. २३, १४; ३. १५, १; ४. ४, १; १५; ५. ४२, १०; ८३, २; ६. २१, ७; ७. १, १३; १०४, ७; १७–१९; २१; ८. २३, १४; ६०, १०; १९; ९. ६३, २९; ७१, १; ८६, ४८; ९१, ४; १०. ७६, ४; ८७, २३; २५; १३२, २; १८२, ३.

र॒क्षसे॑ ९. १०४, ६.

रक्षं॑सा ९. ८५, १.

रक्षां॑सि २. २३, ५; ४. ९, ८; १०. ३७, ५.

रक्षसि १०. २५, ६.
रक्षसे ५. २, ९; १०; ६. ४२, २; ६२, ९.
रक्षसे ७. १, १९.
रक्षस्व १०. ६९, ४.
रक्षस्विनः १. १२, ५; ३६, २०; ८. ६०, २०.
रक्षस्विनं ७. ९४, १२.
रक्षस्विना ८. २२, १८.
रक्षस्विनैः ८. ४७, १२; ६०, ८.
रक्षांसि १. ७९, १२; ६. १६, २९; ४८; ६३, १०; ७. १५, १०; ३८, ७; ८. २३, १३; ३५, १६; ४३, २६; ९. १७, ३; ३७, १; ४९, ५; ५६, १; ६३, २८; ११०, १२; १०. ३६, ४; ८७, ९; १९; ९८, १२; १८७, ३.
रक्षाः ७. १०४, १६.
रक्षितः १०. ८५, ४.
रक्षिता १. ८९, ५; ६. ७, ७; १०. ८५, ५.
रक्षितारः १. ८९, १.
रक्षितारं १०. ६७, ६.
रक्षितारा २. ३९, ६.
रक्षितारौ १०. १४, ११.
रक्षिषः ८. ६१, १७.
रक्षिषत् ७. १२, २; ८. ६१, १५.
रक्षेथे इति १. ३४, ८; ३. ५४, १६; ५. ६३, ७.
रक्षो इति १. १७४, ३.
रघवः ४. ५, १३.
रघुः ५. ३०, १४; ४५, ९.
रघुजाःऽइव ९. ८६, १.
रघुऽद्रु १०. ६१, १६.
रघुऽद्रुवः १. १४०, ४; ५. ६, २; ८. १, ९.
रघुपत्मऽजंहाः ६. ३, ५.
रघुऽपत्वा १०. ६, ४.
रघुऽपत्वानः १. ८५, ६.
रघुं ८. ३३, १७.
रघुऽमन्यवः १. १२२, १.
रघुऽयत् ४. ५, ९.
रघुऽया २. २८, ४.
रघुऽयामा ९. ३९, ४.
रघुऽवर्तनिः ९. ८१, २.
रघुऽवर्तनिं ८. ९, ८.
रघुऽस्यत् ४. ५, ९.
रघुऽस्यदः १. ६४, ७; ८५, ६; १४०, ४; ८. ३४, १७.
रघुऽस्यदं ३. २६, २; ५. २५, ६; ७३, ५.
रघू इति १०. ४९, २.
रघ्वी इति ६. ६३, ९.
रघ्वीःऽइव १. ५२, ५; ४. ४१, ९.
रजः १. ५०, ७; ५६, ५; ५८, १; ५; ६२, ५; ८१, ५; ८३, २; ८४, १; ९०, ७; ११०, ६; १३९, ४[२]; १४१, ७; २. ३१, २; ३. १, ५; ४. ३६, १; ४५, २; ५. ४८, २; ५३, ७; ५९, १; ६. ६१, ११; ७. ६६, १५; ८७, २; ८. ८८, ५; ९. २२, ४; ५; ६३, ६; ६८, ९; ७२, ८; ७७, २; १०. ३७, ३; ५६, ५; ६६, ११; १०५, ७; १२९, १; १४३, २; १४९, २.
रजःऽइषितं ८. ४६, २८.
रजःऽतुरं १. ६४, १२; ९. ४८, ४; १०८, ७.
रजःऽतूः ६. २, २; ६६, ७.
रजःऽभिः १. ११६, २०; ६. ६२, २; ६.
रजःऽसु ७. ३४, १६; ८. ७७, ५; १०. ४३, ८.
रजतं ८. २५, २२.
रजसः १. ६, १०; १९, ३; ३३, ७; ५२, ६; १२; १४; ७९, १; ९२, १; १२४, ५; १६०, १; १६४, १९; १६८, ६; २. २, ३; ४०, ३; ३. २६, ७; ४९, ४; ४. १, ११; १७, १४; ५. ४७, ३; ४८, १; ५९, ३; ६९, ४; ६. ६२, ९; ७१, १; ७. ३५, ५; ६४, १; ८७, ६; १००, ५; ८. ५७, ३; ५९, २; ९. ६२, १४; ८६, ३०; १०. ८, ६; २७, ७; ४९, ६; ५३, ६; ९५, १७; १२१, ५; १२३, १; १३९, ५; १४३, ५; १८७, ५.
रजसा १. ३५, २; ९; १६४, १४; १०. ३२, २.
रजसि २. २, ४; ९. ७४, ६; १०. १५, २; ४५, ३; ८२, ४; १२३, ८.
रजसी इति १. १६०, ४; ४. ४२, ३; ६; ५६, ३; ६. ९, १; १५, ९; ७. ८०, १; ९९, १; ९. ६८, ३.
रजांसि १. ३२, १४; ३५, ४; १४९, ४; १५४, १; १६४, ६; १६६, ३; ४; १८०, १; १८१, ५; १८७, ४; २. ३९, ७; ३. ४, ४; ३०, २; ५८, ५; ६२, १६; ४. ४५, ७; ५३, ३; ५; ५. ५४, ४; ६३, ५; ६९, १; ७३, ३; ८१, ३; ६. ७, ७; ३०, ३; ३१, २; ४९, १३; ६९, ५; ७. २१, ६; ६८, ३; ८. ४३, ६; ७३, १३; ८२, ९; ९. ३, ७; ८; १०. ७५, ७; १११, २; ४.
रजिं ६. २६, ६.
रजिष्ठं १. ९१, १.
रजिष्ठया १०. १००, १२.
रजिष्ठाः ७. ५१, २; ९. ९७, २८.
रजिष्ठां ९. ८९, २.
रजिष्ठैः १. ७९, ३; ८. १०१, १०.
रजी इति १०. १०५, २.
रज्जुः १. १६२, ८.
रज्या १०. १००, १२.
रणं ९. ७, ७.
रण ५. ५१, ८; ८. १२, १७; १३, ९.
रणऽकृत् १०. ११२, १०.
रणत् ८. ९३, २०.
रणन् ४. ३३, ७; ५. ५३, १६; १०. २५, १.
रणंत ७. ५७, ५.
रणंति ८. ९२, २०; ९. १११, २.
रणंति ३. ७, ५.
रणे ८. ९६, १६; १०. ११२, १०; ११३, ४.
रणय ८. ३४, ११.
रणयन् १. १००, ७.
रणयंत १. १४७, १; ३. ५७, २; ४. ७, ७; १०. १४८, ३.
रणयंत ६. १, ४.

रणयँतु ६. २८, १.
रणयामसि ८. ९२, १२.
रणस्य ८. २, ४२.
रणाः ६. २७, १; २.
रणाय १. ६१, ६; ९; ११६, २१; १६८, ९; ३. ३४, ४; ४७, १; ५. ३१, ५; ४१, ४; ७. २०, ५; ८. १७, १२; ३३, ९; ९. ९७, ५३; १०. ९, १; ९५, ७.
रणिता ८. ९६, १९.
रणिष्टन २. ३६, ३.
रणे १. ११९, ३; ६. १५, ५; ६७, ११; ९. ६६, १३.
रणेऽरणे १. ७४, ३; ६. १६, १५.
रणेषु १०. १२०, ५.
रण्यः ९. ९६, ९.
रण्यऽजित् ९. ५९, १.
रण्यति ५. १८, १; ८. ३३, १६; १०. ४३, ६.
रण्यति १. ८३, ६; ९. १०७, १८.
रण्यथः ५. ७४, ३.
रण्यंति ८. १६, २.
रण्यंति १. ३८, २.
रण्यऽवाचः ३. ५५, ७.
रण्यसि ८. १२, १८.
रण्या ८. ७७, ११; १०. ११२, ५.
रण्यानि १. ८५, १०; ३. ५५, ७.
रण्वः १. ६६, २; ६९, २; ३; १४४, ७; २. ४, ६; २४, ११; ४. १, ८; ६. २, ७; ३, ३; १०. ११, ५; ६४, १०.
रण्वऽभिः ५. ४४, १०.
रण्वं १. १२८, ८[२]; १२९, ७; ३. २६, १; ४. ७, ५; ६. २९, १; १०. ३३, ६.
रण्वया ७. ५४, ३.
रण्वऽसंदृक् ३. ६१, ५; ७. १, २१.
रण्वऽसंदृशं ६. १६, ३७.
रण्वा १. ६५, ३; २. ४, ४; ४. १६, १५.
रण्वाः ५. ७, २; ७. ५९, ७.
रण्वाः ४. ३७, १.
रण्वासः १०. ११५, ४.
रण्वित इति २. ३, ६.
रत्नऽधाः १. १५, ३; १६४, ४९; २. १, ७; ४. ३४, ६; ९. ६७, १३; ९०, २; १०७, ४; १०. ३५, ७.
रत्नधाऽतमः १. २०, १.
रत्नधाऽतमं १. १, १; ५. ८, ३.
रत्नऽधाभिः ४. ३४, ७.
रत्नऽधेभिः ४. ३४, ८; ३५, ७.
रत्नऽधेयं ४. १३, १; ३४, ४; ३५, १; २; ९; ५. ४२, ७.
रत्नऽधेया ४. ३४, १.
रत्नऽधेयानि ७. ५३, ३; १०. ७८, ८.
रत्नऽधेयाय ४. ३४, ११; ७. ९, ५.
रत्नऽभाजः ७. ८१, ४.
रत्नं १. ४१, ६; ५३, १; ५८, ७; ९१, १; ९४, १४; १२५, १; १४०, ११; १४१, १०; २. ३८, १; ३. ८, ६; १८, ५; २६, ३; ८; ५४, ३; ५६, ७; ४. १, १०; १८; २, १३; ५, १२; १२, ३; ३५, ८; ४१, ३; ४४, ४; ५. ४८, ४; ४९, १; २; ६. १३, २; १९, १०; ६५, ३; ४; ७. १६, ६; १२; २५, ३; ३७, २; ३८, ६; ५२, ३; ७५, ६; ८; ८१, ३; ८. ६७, ७; ९. ४७, ४; ५९, १; ८६, १०; १०. ७४, ३.
रत्नंऽवंतं ३. २८, ५.
रत्ना १. ३५, ८; ३. २, ११; ३, १; ४. ५४, १; ५. १, ५; ६. ७४, १; ७. १७, ७; ३८, १; ७०, ४; ८. ९३, २६; १०. ११, ८.
रत्नानि १. २०, ७; ४७, १; ३. ६२, ४; ४. १५, ३; ५. ७५, ३; ८२, ३; ७. ६७, १०; ८. ९५, ९; ९. ३, ६; ३५, २२.
रत्निनः ७. ४०, १.
रत्निनीं १. १८२, ४.
रत्सिं ५. १०, १.
रथ ६. ४७, २८.
रथऽओळ्ह १०. १४८, ३.
रथः १. ३०, १८; ४६, ३; ८; ५४, ३; ५८, ३; ६६, ३; ९४, ८; १०८, १; ११६, १८; ११७, २; ११८, १; ११९, ३; १२०, ११; १२२, १५; १२३, १; १३५, ४; १४१, ८; १५७, ३; १६१, ३; १६३, ८; १८०, १; १८१, ३; १८२, १; १८३, २; ३; २. १६, ३; ६; १८, १; २९, ४; ३. ११, ५; १५, ५; ४९, ४; ५८, ८; ४. ९, ८; ३१, १४; ३६, १; ४३, ५; ४५, १; ७; ४८, ५; ५. १०, ५; १८, ३; ३७, ३; ७४, ८; ७५, ९; ७७, ३; ६. ३४, २; ४९, ५; ६३, ७; ६८, १०; ७. ३४, १; ३७, १; ६७, ८; ६८, ३; ६९, १; ३; ५; ७१, ४; ८. ९, १८; १३, ३१; १९, ८; २२, ५; २६, ४; ३१, ३; १५; ३३, ४; ११; ७३, १३; ९. ३८, १; ८८, २; ९०, १; ९२, १; ९४, ३; १११, ३[२]; १०. २९, २; ३९, १; ४४, २; १०७, ११; ११२, २; १७६, ३.
रथःऽइव ६. ६१, १३.
रथःपतिः ५. ५०, ५; १०. ६४, १०; ९३, ७.
रथऽक्षयाणि ६. ३५, १.
रथऽचर्षणे ८. ५, १९.
रथऽजित् ९. ७८, ४.
रथऽतुरं ४. ३८, ३.
रथऽतूः १०. ७७, ८.
रथतूःऽभिः १. ८८, २.
रथऽप्रां ६. ४९, ४; ८. ७४, १०.
रथऽप्रोष्ठेषु १०. ६०, ५.
रथं १. २०, ३; २५, १८; ३४, ५; १०; ३५, ४; ५; ४६, ७; ४९, २; ५१, १२; ५२, १; ५४, ६; ५६, १; ६१, ४; ७०, ४; ८२, ४; ८४, ३; ९२, १६; १००, १६; १०२, ३; ५; ९; १०६, १–६; १११, १; ११२, २; १२; ११६, १७; ११७, १३; ११८, ५; ११९, १; २; ५; ७; १२०, १०; १२९, १; १०; १३०, ६; १५७, १; २; १६१, ६; ७; १६४, २; ३; १६७, ५; १७५, ३; १७७, ३; १७८, ३; १८०, १०; १८२, २; २. १०, २;

१२, ८; २०, १; २३, ३; ३१, १–४; ३७, ५; ४०, ३; **३.** २, १; १५; २५, ४; ४४, १; **४.** २, १४; १६, २०; ३३, ८; ४३, २; ४५, ३; ४६, ४; **५.** १, ११; २, ११; २९, १५; ३१, ४; ११; ३३, ३; ३५, ७; ८; ५६, ८, ६३, १; ५; ७; ७३, ५; ७४, ३; ७५, १; **६.** १८, ९; २६, ४; ३१, ५; ३७, १; ४४, २४; ४५, १४; ४७, २७; ५३, १; ६३, ५; ७५, ८; **७.** २३, ३; ३२, १०; ४८, १; ६७, १; ७१, ३; ७४, २; ९०, ५; **८.** १, ३५; ५, २८; ३४; ८, १०; ९, ८; १०, ६; १३, २३; २२, १; २५, २२; २६, १; ३३, १८; ३५, २२; ४५, ९; ४६, २४; ४८, ५; ५८, ३; ६८, १; ६९, १५; १६; ७३, १; ८०, ४–६; ८४, १; **९.** ७१, ५; ७५, १; ९६, २; १०७, १३; ११२, ४; **१०.** ४, ६; ११, ९; २३, ३; २६, ९; २९, ८; ३५, ६; ३९, ४; १२; १४; ४०, १; ६; ४१, १; २; ५३, ७; ६०, २; ६३, १४; ७०, ५; ७५, ९; १०१, ७; १०२, १; १०३, ५; ११४, ६; ११९, ३; १३२, ७; १३५, ३–५; १३८, ३; १४३, १; १७१, १.

रथंऽइव **१.** ९४, १; **२.** २, ३; **७.** ४१, ६.

रथंऽतरं **१०.** १८१, १.

रथंऽतरे **१.** १६४, २५.

रथऽया **८.** ४६, १०.

रथऽयावाना **८.** ३८, २.

रथऽयुः **१.** ५१, १४; **७.** २, ५; **१०.** ७०, ५.

रथऽयुजः **१.** १३९, ४; **८.** ३३, १४.

रथऽयुजं **५.** ४१, ६.

रथर्यतः **८.** १०१, २.

रथर्यति **९.** ३, ५.

रथर्यसि **१०.** ३७, ३.

रथंऽवत् **५.** ५७, ७; **७.** २७, ५; ७७, ५.

रथंऽवते **१.** १२२, ११.

रथऽवाहनं **६.** ७५, ८.

रथंऽवीतिः **५.** ६१, १९.

रथंऽवीतौ **५.** ६१, १८.

रथऽसंगे **९.** ५३, २.

रथऽसहा **८.** २६, २०.

रथऽस्पृशः **१०.** ९५, ८.

रथस्य **१.** ३०, १९; ३४, ९; ५०, ९; ७४, ७; ८८, २; १८०, ९; **२.** १८, ७; **३.** ३५, २; ४५, २; ५३, ५; **५.** ७३, ३; **६.** ६२, २; **८.** २२, ४; ७२, ६; ९१, ७; **१०.** २६, ८; ५९, १; ११४, १०; १३२, ४; १६८, १.

रथा **७.** १८, २२.

रथाः **१.** ३८, १२; १८६, ८; **४.** १४, ४; ४५, २; **५.** ३३, ५; ५५, १.

रथाःऽइव **४.** १९, ५; **७.** ७४, ६; **८.** ३, १५; **९.** १०, १; २; २२, २; ६७, १७; ६९, ९.

रथात् **५.** ३६, ३.

रथान् **१.** ११२, २२; **२.** ८, १; **५.** ५३, ५; **६.** ४७, २४.

रथानां **१.** ४८, ३; **४.** ३८, ६; **५.** ५२, ९; ५३, १०; ६६, ३; ७४, ८; **७.** ३२, ११; ४४, ४; **८.** २३, २; ६८, ४; ९४, १; १०३, १०; **९.** ९६, १; **१०.** २६, ५; ७८, ४; १०३, ४; १०; १७८, १.

रथान्ऽइव **१.** १३०, ५[२]; **२.** २३, १३; **५.** ७३, १०; **८.** १२, ३.

रथाय **१.** १११, ३; १४०, १२; **५.** ३१, १; **८.** ६८, १३.

रथासः **१.** १२६, ३; **२.** १२, ७; ४१, १; **१०.** १४२, ५.

रथिऽतमः **६.** ४५, १५; ५६, २; ३; **८.** ४५, ७; ६१, १२; **९.** ६६, २६.

रथिऽतमं **१.** ११, १; **६.** ५५, २; **८.** ९९, ७.

रथिऽतमा **१.** २२, २; १८२, २.

रथिऽतरः **१.** ८४, ६.

रथिनः **१.** १२२, ८; **६.** २७, ८; ४७, ३१; **९.** ९७, ५०.

रथिने **१०.** ४७, ५.

रथिनां **१.** ११, १; **८.** ४५, ७.

रथिनीः **१.** ९, ८.

रथिने **१०.** ४०, ५.

रथिर्यंतीऽइव **१.** १६६, ५.

रथिरः **३.** १, १७; ३१, २०; **९.** ७६, २; ९७, ४६; ४८.

रथिरं **३.** २६, १; **७.** ७, ४.

रथिरा **७.** ६९, ५.

रथिरायतां **९.** ९३, ४.

रथिरासः **८.** ५०, ८; **९.** ९७, ३७; **१०.** ७६, ७.

रथी **८.** ४, ९.

रथीऽइव **५.** ८३, ३; **१०.** ५१, ६.

रथीः **१.** २५, ३; ४४, २; ७७, ३; **३.** २, ८; ३, ६; ३०, ११; **४.** १०, २; **६.** ५, ३; ४८, ९; ५५, १; **८.** ११, २; **१०.** १०२, २.

रथीःऽइव **४.** १५, २; **५.** ६१, १७; **८.** ७५, १; ९५, १; **९.** ६४, १०.

रथे **१.** ६, २; १३, ४; १४, १२; १६, २; ३४, २; ४७, ३; ६; ५०, ८; ९४, १०; ११८, ४; १३४, ३; १३९, ३; ४; **२.** १८, ३; ३४, ७; **३.** ३५, १; ४१, ९; **४.** ४४, २; **५.** १७, ४; ४३, ५; ५४, ११; ७५, ४; **६.** २९, २; ४७, १९; ५५, ६; ५९, ५; ७५, ६; **७.** ३२, २; ६६, १५, **८.** १, २४; २५; ३१; ७, २८; २०, ८; २२, ९; २६, २३; ६५, ४; ८५, ७; ९८, ९; **९.** २१, ४; ६२, १७; ८९, ४; ९८, २; **१०.** ३३, ५; ६४, १२; ९६, ६; १२.

रथेन **१.** २२, ४; ३४, १२; ३५, २; ४७, २; ७; ९; ४८, १०; ११३, १४; ११६, १; २०; ११७, १५; ११८, २; ३; १०; १२३, ५; ७; १२५, ३; १३४, १; **२.** २७, १२; १६; **३.** ३३, ९; १०; ५३, १; **४.** ४, १०; १४, १; ३; ४४, ४; ५; ४६, ५; ४८, १; **५.** ३१, ९; ८३, ७; **६.** ४५, १५; ६२, १०; **७.** ६७,

३; ७१, २; ७२, १; २; ७५, ६; ७८, १; ८. ५, २; ३५; ८, २; ११; २०, १०; २२, १५; ५७, १; ७३, २; ८५, ८; १०. ३९, ७; ७०, ३; ८५, २६; १०३, ४.
रथेभिः १. ४८, ७; ८८, १; १००, १०; २. १५, ४; ५. ५, ३; ५८, ६; ६. ७५, ७; ८. ७०, १; ९. १५, १.
रथेभ्यः १. ९४, ११.
रथेऽशुभं १. ३७, १; ५. ५६, ९.
रथेषु १. ३९, ६; ६४, ९; ८५, ४; ५; ८७, २; १६६, ९; २. ३४, ८; ५. ५३, २; ४; ५६, ६; ७; ५७, ६; ६०, २; ४; ६१, १२; ८. २०, १२.
रथेऽस्थाः १. १७३, ४; ५; ६. २९, २.
रथेऽस्थां ६. २१, १; २२, ५; ८. ३३, १४; ९. ९७, ४९.
रथेऽस्थाय ८. ४, १३.
रथेऽस्थेन २. १७, ३.
रथैः १. ११६, ४; ८. ७, १७.
रथैःऽइव ५. ६०, १.
रथ्यः २. ४, ४; ३१, ७; ९. ३६, १.
रथ्यः १. १२१, १४; १४८, ३; २. २४, १५; ३. ६, ८; ४. १६, २१; ५. ५४, १३; ८७, ८; ६. ५१, ६; ९; ७. २१, ३; ८. १९, ३५; ४७, ५; १०. ७८, ५; ९१, ७; १३०, ७.
रथ्युः ७. ५६, २१; ६६, १२; ८. ८३, ३.
रथ्यं १. ३५, ६; ९. २१, ६.
रथ्यं ६. ७, २; ४६, २; ४९, १५; ७. ५, ५; ८. १०३, ७; ९. १६, २; १०. २३, १; ९२, १.
रथ्यस्य ४. ४१, १०; ५. ४१, ३.
रथ्या १. ५३, ९.
रथ्या १. १५७, ६; १८२, २; ५. ७५, ५; ८. २५, २; १०. १०२, ११.
रथ्या १. ३४, ७; ५. ७६, १; ६. ६२, ७.
रथ्याऽइव १. १८०, ४; २. ४, ६; ४. १, ३; १०. ८९, २; ११७, ५.
रथ्याऽइव २. ३९, २; ३; ३. ३३, २; ३६, ६; ७. ३९, १; ९५, १; १०. १०, ७; ८.
रथ्यासः ९. ८६, २.
रथ्यासः ६. ३७, ३.
रथ्ये ९. ९१, १.
रथ्ये ८. ४४, २७.
रथ्येभिरिति रथ्येभिः १. १५७, ६.
रदं १. १६९, ८; ६. ६१, ६.
रद १. ६१, १२; ९. ९३, ४.
रदत् ७. ८७, १.
रदति १. १६६, ६.
रदता १. ११७, ११.
रदति ७. ६०, ४.
रदती ५. ८०, ३.
रदतीः २. ३०, २.
रदतु ७. ६२, ३.
रदवसो इति रदऽवसो ७. ३२, १८.
रद्धं १०. ११३, ८.
रधं १. ५०, १३.
रधाम १०. १२८, ५.
रध्रऽचोदः २. २१, ४.
रध्रऽचोदनः ८. ८०, ३.
रध्रऽचोदनं ६. ४४, १०; १०. ३८, ५.
रध्रऽतुरः ६. १८, ४.
रध्रं २. ३४, १५; ७. ५६, २०.
रध्रस्य २. १२, ६; १०. २४, ३.
रन् १. १२०, ७.
रंत १. ६१, ११; ७. ३९, ३.
रंतयः ७. १८, १०; ९. १०२, ५.
रंता ९. ९२, ३.
रंते ७. ३६, ३.
रंत्यः १०. २९, ३.
रंधय १. ५१, ८; १३२, ४; ३. ५३, १४; ६. १९, १२; ५३, ५; ७. ३०, २; १०. ८७, ८.
रंधयः ६. ४३, १.
रंधयत् २. १९, ६.
रंधयन् १. ५०, १३; ५१, ९.
रंधयं १०. ४९, ४; ५.
रंधयस्व ३. ३०, १६.
रंधयानि १०. २८, ९.
रंधि ४. २२, ९.
रंधिं ७. १८, १८.
रंधीः १. १७४, २; ४. १६, १३; ७. ३१, ५.
रंध्रे ८. ७, २६.
रपः ७. ३४, १३; ८. १८, ८; १६; ६७, २१; १०. ५९, ८^{2}; ६०, ११; ९७, १०; १३७, २; ३.
रपत् १. १७४, ७; १०. ११, २.
रपति १०. ६१, १८.
रपसः २. ३३, ३; ७.
रपसा ७. ५०, १.
रपांसि १. ३४, ११; ६९, ४; १५७, ४; ६. ३१, ३.
रपामि १०. १०, ११.
रपेम १०. १०, ४.
रप्शते ४. ४५, १; १०. ११३, २.
रप्शदूधऽभिः २. ३४, ५.
रप्शुदा ८. ७२, १२.
रफितायं १०. ११७, २.
रभः १. १४५, ३.
रभःऽदां ६. २२, ५.
रभध्वं १०. ५३, ८; १०३, ६.
रभंते ३. २९, १३.
रभसं २. १०, ४; ३. ३१, १२; ६. ६१, १.
रभसस्य ९. ७३, ६.
रभसा ३. १, ८.
रभसाः १. ८२, ६; ५. ५४, ३.
रभसानः ६. ३, ८.
रभसानि ९. ९६, १.
रभसाय १. १६६, १.
रभसासः १. १६६, १०; १०, ९५, १४.
रभस्व १०. ८७, २; ८; १५५, ३.
रभस्वतः १. ९, ६.
रभस्वत्ऽभिः १०. ३, ७.
रभस्वान् १०. ३, ७.
रभामहे ६. ५७, ५; १०. १३३, ६; १३४, ७.
रभिः ८. ५, २९.
रभिष्ठाः ५. ५८, ५.

रभे ३. ५३, २.
रभेमहि १. ५३, ४; ५[२]; ८. ३२, ९.
रभ्यसः १. १२०, ४.
रमंते ८. १०१, ४.
रमते २. ३८, २; १०. १४५, ४.
रमध्वं ३. ३३, ५.
रमंते २. ३०, १; १०. १११, ९.
रमयं ५. ५२, १३.
रमय १०. ४२, १.
रमयः १. १२१, १३.
रमयत् १. ५६, ३.
रमयंति ७. ५६, १९.
रमस्व १०. ३४, १३.
रंवंते १०. ८६, १६.
रंभं ८. ४५, २०.
रंभिनीऽइव १. १६८, ३.
रंभी २. १५, ९.
रंऽसु २. ४, ५.
रंऽसुजिह्वः ४. १, ८.
रयिः १. ६६, १; ७३, १; १२७, ९; २. १, १२; ३. ६२, ३; ४. २, ५; ७; ११, ४; ३६, ५; ५. २५, ७; ५०, ५; ६. १३, १; १४, ५; १५, १२; २०, १; २१, १; ६८, ७; ७. १५, ५; ३२, २१; ८४, ३; ८. ३१, ११; ५१, ९; १०; ९. ५, ३; १०१, ७; १०. १९, ३; ११७, १.
रयिःऽइव १. १२८, १.
रयिणां १०. १२२, ३.
रयिऽदौ ३. ५४, १६.
रयिंऽतमः ६. ४४, १.
रयिऽपतिः १. ६०, ४; ७२, १; २. ९, ४; ४०, ६; ९. ९७, २४.
रयिऽपते ६. ३१, १.
रयिऽभिः १. ६४, १०.
रयिं १. १, ३; ८, १; १२, ११; ३०, २२; ३४, ५; १२; ४७, ६; ४८, १३; ५८, ६; ६४, १५; ६८, ३; ७९, ८; ९; ८५, १२; ९२, ८; ९७, १; ११६, ३; १९; ११७, २३; १२९, ७; १३३, ७; १४१, ११; १५९, ५; १६२, २२; १६९, ४; २. २, ६; ४, ८; ७, १; ११, १३; १५, ५; १९, ५; २५, २; ३०, ११; ४०, ६; ४१, ९; ३. १, १९; १४, ६; २४, ५; ४५, ४; ५१, ५; ५४, १३; ४. १२, २; ३३, ८; ३४, २; १०; ३५, ६; ३६, ८; ९; ३७, ५; ८; ४४, ६; ४९, ४; ५०, १०; ५१, १०; ५३, ७; ५. ४, ७; ११; ९, ७; १०, ७; २०, १; २३, १; २; २४, २; ३३, ६; ४१, ५; ४२, १८; ५४, १४; ८०, ३; ८६, ६; ६. १, ३; ५, ७; ६, ७; ८, ५; १०, ५; १६, २०; २८; २९; २८, २; ४७, ६; ४९, १५; ५९, ९; ६४, ४; ६५, ६; ६८, ५; ६; ८; ७०, ६; ७. १, ५; २४; ५, ९; १६, ९; २०, ७; ३६, ७; ३७, ६; ३९, ६; ४२, ६; ७५, २; ७६, ७; ७७, ६; ८४, ४; ९२, ३; ९३, ४; ९७, १०; ८. ३, ११; ५, १०; १५; ३६; ६, ९; ७, १३; १३, ५; १२; २३, १२; २४, ३; २८; ४०, १; ४३, १५; ४६, १९; ६०, ११; ७१, ३; ६; ७५, ११; १२; ९०, ४; ९३, २१; ३४; ९५, ८; ९; ९७, ३; ९. ४, ७; ८; १०; ७, ९; ११, ९; १२, ९; १३, ५; १९, ६; २०, ४; २९, ६; ३१, १; ३५, १; ४०, ३; ५; ६; ४३, ४; ४८, ३; ६१, ६; ६२, १२; ६३, १; ११; १२; २३; ६५, ३०; ६६, २१; ६७, ६; ६८, १०; ७२, ८; ८६, ४१; ८७, ६; ९३, ४; ५; ९७, २१; ४४; ९८, १; ४; १००, २; १०१, ९; १०२, ३; १०६, ९; १०७, २१; १०. १५, ७; ११; १९, १; २१, ४; ३८, २; ४०, १३; ४७, १; ७६, ४; ८५, ४१; ९१, १५; १३४, ४; १४०, ५; १५६, ३; १६७, १; १८३, १.
रयिऽमत् १०. ३६, १०.
रयिऽमंतः १०. ७४, १.
रयिंऽइव १. ६०, १; २. १३, ४.
रयिऽयन् ३. ६२, २.
रयिऽवः १. १२९, ७; ६. ५, ७; ४४, १.
रयिऽवत्सः ६. ६८, ५.
रयिऽवित् २. १, ३; ३. ७, ३.
रयिऽवृधः ७. ९१, ३.
रयिपाट् १. ५८, ३; ९. ६८, ८.
रयिऽसाचः १. १८०, ९.
रयिऽस्थानः ६. ४७, ६.
रयीणां १. ४६, २; ६०, ४; ५; ६८, ४; ७०, ३; ७२, १; ७३, ४; ९६, ७; १८१, १; २. ९, ४; २१, ६; ३८, १०; ४०, १; ३. ७, ३; ५४, १६; ४. ५०, ६; ५. ३, ८; ३६, १; ६. १, ८; ७, २; ३१, १; ४५, १९; ६०, १३; ७. ५, ५; १०, ५; ८. ८, १२; १९, ८; ४६, २; ७५, ४; ९. ४७, ५; ९७, २४; १०१, ६; १०२, ४; १०. ५, १; ४५, ५; ४७, २; १०६, ७.
रय्या १०. १९, ७.
ररक्षे १. १४७, ३.
ररक्षाणः ४. ३, १४.
ररण ९. १०७, १९; १०. ८६, १२.
ररणः ८. ३२, ६.
ररणत् १. १०, ५; ९१, १४.
ररते ५. ७७, ४; ८. ३१, २.
ररधुः ७. १८, १८.
ररन् १. १२२, १२.
ररंत ५. ५४, १३.
ररंतु ३. ४२, ८.
ररंधि १. ९१, १३; ३. ४१, ४; ६. २५, ९; १०. ५९, ५.
ररपीति ६. ३, ६.
ररप्शे ४. २०, ५.
ररप्शे ६. १८, १२.
ररभे १. १६८, ३.
ररम्भ ८. ४५, २०.
ररहाणः १०. १३९, ४.
ररहाणाः १. १३४, १; १४८, ३.
रराणः ३. १, २२; ४. १, ५; २, १०; ५. ४१, ८; ४३, १३; ६. २३, ७; १०. ६१, १२; ९८, ७; १६९, ४; १८३, १.

ररा॒णः ३. ४, ९.

ररा॒णता १. १७१, १.

ररा॑णा १. ११७, २४; २. ३२, ५; १०. ६१, १५.

ररा॑णाः ४. ३६, ९; ५. ३३, ८.

ररा॒थां १. ११७, २३.

ररा॒थे इ॒तिं ६. ७२, ५.

ररा॒दे ७. ४९, १.

ररा॒धे १०. १०७, ६.

ररा॑वा १०. ४०, ७.

ररा॑ण्णां ८. ३९, २.

र॒रि॒म २. ५, ७; ३. १४, ५; ३२, २; ३५, १; ५. ४३, ३; ८. २, १.

र॒रि॒ऽवान् १. १३८, ४.

र॒रि॒षे २. १, ५.

र॒री॒थाः ६. ४४, ११.

र॒री॒ध्वं ५. ८३, ६.

र॒रे ७. ३९, ६; ५९, ५; ९९, ६; १०. ४९, ३.

र॒वंः १. ९४, १०.

र॒वथः १. १००, १३.

र॒वथेंन ९. ८०, १.

रवें ३. ३१, ६; ५. ६३, ३; ९. ७२, ३.

रवेंण १. ६२, ४; ७१, २; ४. ५०, १; ४; ५; ७. ३३, ४; ७९, ४; ९. ९७, ३६; १०. ६७, ६; ९४, १२; १११, २.

र॒श॒नया॑ ४. १, ९; १०. १८, १४; ७०, १०.

र॒श॒ना १. १६२, ८.

र॒श॒नाः १. १६३, ५; १०. ५३, ७.

र॒श॒नाभिः ९. ८७, १; १०. ४, ६; ७९, ७.

र॒श॒नां १. १६३, २; ५. १, ३.

र॒श॒नांऽइव २. २८, ५.

र॒श्मयः १. ५०, ३; ५९, ३; १०५, ९; १०९ ७; १३५, ९; २. ५, २; ३. ७, ९; ४. १३, ४; ५२, ५; ५. ५५, ३; ६. २९, २; ७५, ६; ९. ६४, ७; ६९, ६; ८६, ६; १०. ९१, ४.

र॒श्माऽइव ६. ६७, १.

र॒श्मिः १. ३५, ७; १०. १२९, ५.

र॒श्मिना ८. २५, १८.

र॒श्मिऽभिः १. १९, ८; ४७, ७; ४९, ४; ८४, १; ८७, ६; ९२, १२; १२३, १२; १२४, ८; १३२, ३; १३६, २^{२}; १३७, २; ४. १४, २; ३; ५२, ७; ५. ४, ४; ७९, ८; ८१, ४; ७. २, १; ३६, १; ४७, ४; ७७, ३; ८. १२, ९; ४३, ३२; ७२, १६; १०१, २; ९. ४१, ५; ६१, ८; ६६, २७; ८६, ३२; ९७, २३; १००, ८; १११, ३; १०. ३५, ५; ७७, ५; १३२, ६.

र॒श्मिं १. १२३, १३; ४. २२, ८; ५. ७, ३; ३३, ३; ८. ७, ८; ३२, २३; ९. ९७, ३३; १०. ९३, ९.

र॒श्मिपु १. १३४, ४^{२}.

र॒श्मीन् १. २८, ४; १०९, ३; १४४, ३; १०. १३०, ७.

र॒श्मीन्ऽइव १. १४१, ११; ८. ३५, २१.

र॒श्मे ५. १९, ५.

रसंऽआशिरः ३. ४८, १.

रसंः ६. ४४, २१; ८. ३, २०; ९. ३८, ५; ४७, ३; ६१, १७; १८; ६७, ८; १५; ७४, ९; ७६, १; ७७, ५; ८४, ५; ८६, १०; ९६, २१; १०. ९, २.

रसं १. ७१, ५; १०५, २; ५. ४३, ४; ७. १०४, १०; ८. ५३, ३; ९. ६, ६; १६, १; २३, ५; ६२, ६; ६३, १३; ६४, २४; ६५, १५; ६७, ३१; ३२; ७९, ५; ९७, १; १०९, ११; ११३, ३; १०. ७६, ७.

र॒सया॑ ४. ४३, ६; १०. ७५, ६; १२१, ४.

रसंऽवत् ५. ४४, १३.

रसंऽवान् ६. ४७, १.

रसंस्य १. ३७, ५; ९. ८५, १.

र॒सा ५. ४१, १५; ५३, ९; ८. ७२, १३.

र॒साऽइव ९. ४१, ६.

रसाः १. १८७, ४; ६. ६३, ८; ८. ४९, २; ९. ११३, ५.

रसानां १. १८७, ५.

र॒सां १. ११२, १२.

र॒सायाः १०. १०८, १; २.

र॒साय्यः ९. ९७, १४.

र॒सिनः ८. १, २६; ३, १; ९. ११३, ५.

रसें ९. १४, ३.

रसेंन १. २३, २३; ९. ९७, १२; ५७; १०९, २०.

र॒हु॒सूःऽइव २. २९, १.

रहूगणाः १. ७८, ५.

रा॒का २. ३२, ८; ५. ४२, १२.

रा॒कां २. ३२, ४.

रा॒के २. ३२, ५.

रा॒ज॒काः ८. २१, १८.

रा॒ज॒तः १०. १३, ५.

राजंति १. १४३, ४.

रा॒ज॒ति १. ३, १२; २. ४३, १; ४. ५३, ४; ५. २५, ४; ८१, २; ६. ४७, १९; ९. ५, १; ३; ६१, १८; ७१, ७; ७५, ३; ९६, १८; १०. १७०, १; १८९, ३.

राजंते ८. १९, २२.

रा॒ज॒थ ५. ५५, २; ८. ७, १.

राजंथः ५. ७१, २; ७. ८३, ५.

रा॒ज॒थः ३. ६२, १७; ४. ५६, ६; ५. ३८, ३; ६३, २; ७.

राजंन् १. २४, १४; ९१, ४; ६. ४६, ६; ८. ७९, ९.

रा॒ज॒न् १. २४, ९; ६३, ७; ७९, ६; ९१, ८; २. २७, १७; २८, ९–११; २९, ७; ३०, ९; ४. १९, १०; ५. ४, १; ३६, २; ६. १, १३; ७, ३; ८, ५; १२, २; १९, १०; ३९, ५; ७. ८६, ५; ८९, १; ८. ४८, ७; ८; ७९, ८; ९७, १५; ९. ११, ३; ६१, १७; ११३, ४; ११४, ४; १०. १, ६; ३, १; ४, १; १४, ४; ११; २५, ७; ४४, २; ६०, ६; ८७, ३; २१; ९७, २२; १२४, ५; १२८, ५.

राजंनि १. १०८, ७; ४. ५०, ८; ५. ३०, १४; ६. १, १३.

रा॒ज॒नि १०. ४९, ४.

राजंतं १. १, ८; ४५, ४; ३. २, ४; ६. १, ८.

रा॒जंति॒ ३. ५६, ८.

राजं॑ती इति॑ ६. ७०, २.
राजं॑तौ ८. ८, १८.
राजन्य॑ः १०. ९०, १२.
राज॑ऽपुत्रा २. २७, ७.
राजपुत्राऽइ॑व १०. ४०, ३.
राज॑ऽभिः १. २०, ५; ४०, ८; ४. ३४, ११; ७. ८३, ६; १०. ४२, १०.
राज॑ऽभ्यः १. १३९, ७; २. २७, १; ३; १२.
राजऽयक्ष्मात् १०. १६१, १.
राज॑सि १. १४४, ६.
राजसि १. २५, २०; ३६, १२; १८८, १; ३. १०, ७; ५. ८, ५; २८, २; ८१, ५; ७. ३२, १६; ८. १३, ४; १५, ३; ५; १९, ३१; ३७, ३; ६०, १५; ९. ६६, २; ८६, ५; २८; १०. १४०, ४; १६७, १.
राज॑ऽसु ८. १०१, ५.
राजसे ८. ९७, १०; ९. ८६, ३६.
राजा॑ १. २४, ७; ८; १२; १३; ३२, १५; ५४, ७; ५९, ३; ५; ६५, ४; ७३, ३; ९१, ५; ९८, १; १२६, १; १५६, ४; १७४, १; १७७, १; १७८, २; २. १, ४; २, ८; १४, ११; २७; १०; ३. १, १८; ४६, २; ४७, १; ५३, ११; ५५, ४; १७; ५९, ४; ४. १७, ५; २०; ४२, २; ५०, ७; ९; ५. ३७, ४; ४०, ४; ७; ८५, ३; ६. ९, १; १५, १३; २०, ३; २२, ९; २४, १; ३०, ५; ३६, ४; ३७, २; ४४, १३; ४७, १६; ७५, १८; ७. ८, १; १८, ११; २७, ३; ३४, ११; ४१, २; ४९, ३; ४; ६४, १; ८७, ५; ६; ९७, ३; ८. १९, ८; २१, १८; ६४, ३; ६५, १०; ७०, १; ९५, ३; ९. ६५, १६; ७६, ४; ७८, १; ८३, ५; ८५, ९; ८६, ८; ३३; ४०; ४५; ८९, २; ९२, ६; ९६, १०; ९७, १०; २३; २४; ३०; ४०; ५६; १०७, १५; १६; १०८, ८; ११३, ८; १०. १२, ५; ३४, ८; १२; ४५, ५; ६१, १६; ९५, ५; १००, ४; १०९, २; १२१, ३; १६८, २; १७३, ४; ५.
राजा॑ऽइव १. ६७, १; १३०, १; ४. ४, १; ६. ४, ४; ७. १८, २; ९. ७, ५; २०, ५; ५७, ३; ८२, १; ९०, ६; १०. ४३, २; ७५, ४.
राजा॑नः १. ४१, ३; ७. ४०, ४; ६६, ६; ११; ८३, ७; ९. १०, ३; १०. ७८, १; ९३, ४; ९७, ६; १०९, ६; १२६, ६.
राजानः १. १२२, ११; ८. १९, ३५.
राजा॑नःऽइव १. ८५, ८.
राजा॑नं १. २३, १४; २. १, ८; ३. ४३, ५; ४. १, २; ३, १; ४२, ९; ५. २, ६; ३९, ४; ५४, ७; १४; ५८, ४; ६. ८, ४; ७. ३१, १२; ८. ४३, २४; ९. ४८, ३; ७०, ३; ८५, ३; ११४, २; १०. १४, १; ३३, ४; १२४, ८; १४१, ३.
राजा॑ना १. ७१, ९; २. ३६, ६; ५. ६२, ६; ६५, २; ६. १६, २४; ८. १०१, २; १०. १४, ७; ६४, ५.
राजाना १. १३६, ४; १३७, १; ३. ३८, ५; ६; ७. ६४, २; ४; १०. ६१, २३.
राजा॑नौ २. ४१, ५; ६. ६२, ९.
राजानौ ७. ८४, १; १०. ३९, ११.
राजा॑मि ४. ४२, १.
राज्ञ॑ः १. ९१, ३; १२२, १५; १२६, २; ६. ५१, ४; ८. ४, १९; ५, ३८; १०. ४०, ५; १०३, ९; १६७, ३.
राज्ञा॑ १०. ९७, २२.
राज्ञे॑ १. ५३, १०; ७१, ४; १०. १४, १५.
राज्यं॑ ७. ६, २.
राट् ५. ४६, ८; ६. १२, १; ५.
रातः ७. ६७, ७.
रातऽत॑मा १. ६१, १.
रातं॑ १. १६२, ११; ८. ३२, २१; १०. ११६, ७.
रातय॑ः १. ११, ३; ८; २९, ४; १३२, २[२]; ८. ४९, ५; ६२, १.
रातये॑ ५. १०, ६.
रातस्य॑ ८. ५, १४.
रातऽह॑विषे २. ३४, ८.
रातऽह॑व्यः १. ३१, १३; ५४, ७; ११८, ११; १५३, ३; २. २५, १; ४. ७, ७; ४४, ३; ८. १०३, १३.
रातऽह॑व्यस्य ५. ६६, ३.
रातऽह॑व्या ७. ३५, १.
रातऽहव्या ६. ६९, ६.
रातऽह॑व्याः ५. ४३, १४; ६. ११, ४.
रातऽह॑व्यां ५. ४३, ६.
रातऽह॑व्याय ५. ५३, १२; ७. १९, ६.
राता ३. ३५, ७.
राता॑नि १. १३१, १.
राति॑ः १. ३४, १; ८९, २; ११७, १; १२२, ७; १३९, ५[२]; १६८, ७; १८४, ४; ३. ३०, ७; ५. ३८, १; ६. ४५, ३२; ५८, १; ६३, ४; ७. २५, ३; ८. १३, ४; १९, १९; २४, ९; ९२, २९; १०. ६६, १०; ९५, १७; १३३, ३; १४३, ४; १८०, १.
रातिनी॑ ४. ६, ३.
राति॑नी ३. १९, २.
राति॑ऽभिः १. ११, ६; ३. १९, २; ८. १९, २९.
राति॑ं १. ६०, १; १६२, २; १६९, ४; २. १, १६; २, १३; ३. २, ४; ६२, ११; ४. ५, २; १७, ५; ३४, १०; ६. ३८, १; ६३, ८; ७. ३८, ५; ५६, १८; ८. ९, १६; २३, २८; ७१, ८; ७९, ५; १०१, ८; १०. १४०, ५; १७८, २.
राति॑षु ८. ४, १९; १९, १२; ३४, १८.
रातिऽसा॑चः २. १, १३; ६. ४९, १४; ७. ३४, २२; २३; ३५, ११; ३८, ५; ४०, ६; १०. ६५, १४.
रातिऽसा॑चं ७. ३६, ८.
रातौ॑ ५. ३३, ९; ६. ५०, ९; ७. १, २०; २५; २५, ४; ३७, ८.
रात्रि॑ १०. १२७, ८.

रात्रीं १. ११३, १; ११५, ४; ५. ३०, १४; १०. १२७, १; १९०, १.

रात्रीः १. ११६, २४; १०. ९५, १६.

रात्रीभिः १०. १०, ९.

रात्री १. ३५, १; ५. ८१, ४.

राभ्याः १. ९४, ७; १०. १२९, २.

राभ्यो १०. ६८, ११.

राधः १. ९, ५; १०, ७; ४४, १; ४८, २; ५१, ७; ५७, १; १००, १७; ११०, ९; १२१, ५; १२२, ८; ११; १५९, ५; २. ९, ४; १२, १४; १३, १३; १४, १२; २२, ३; ३४, ११; ३८, ११; ४. २१, ९; ३१, ९; ३२, १८; ५. १३, ६; ३९, १; ५२, १७[२]; ५३, १३; ५७, ७; ६३, २; ७९, ५; ६. ४७, १४; २२; २५; ७. ५, ८; १६, २; २२, ८; २७, २; ३; ७७, ४; ५; ७९, ४; ८१, ५; ९२, ३; ९६, २; ८. ४, १९; २४, २१; २९; ५४, ५; ८; ५५, १; ५६, १; ६४, १; ८०, १०; ९०, ६; १०३, ७; ९. १, ३; ६१, २७; ९७, ६; १०. ७, २; २९, ३; ६१, ११; ९६, ५; १५९, ५.

राधःऽदेयाय ४. ५१, ३; ८. ४, ४.

राधःऽपते ८. ६१, १४.

राधःऽभिः ६. ६०, ३.

राधत् १. १२०, १.

राधति १०. ६३, ६.

राधसः १. १५, ५; २२, ७; ८१, ६; ४. २०, ७; ५. ३८, १; ८६, ४; ६. ४४, ५; ४७, २२; ५५, २; ६०, १३; ७. २८, ५; ७६, ७; ८. १४, ४; २१, १६; २४, ८; ४६, ११; ५०, ६; ६१, १४; ९. ४६, ५; ८१, ३; १०. १४०, ५.

राधसःऽराधसः ६. २७, ३.

राधसा १. ४८, १४; ५४, ७; ९४, १५; १३५, ४[२]; ३. ३०, २०; ४. ५५, १०; ५. ४३, ९; ६. ४, ७; १०, ५; ८. १, १४; २३; २४, १३; ८१, ४; ५; ९७, ६; १०. २३, १.

राधसां ८. ९०, २.

राधसि ४. ३२, २१.

राधसे १. १७, ७; ८१, ८; १३९, ६; ३. ४१, ६; ५१, १२; ४. २०, २; २४, १; २९, ३; ५. ३५, ४; ६. ३८, ५; ७. ७९, ५; ८. १, ६; २, २९; २४, १०; १२; ४५, २४; ४९, ३; ६४, १२; ६८, ७; ७०, ९; ९३, १६; ९. ८, ३; ६०, ४; ९७, ४२; १०. १७, १३.

राधांसि १. २२, ८; ८४, २०; ५. ७९, ६; ७; ६. ४४, १२; ४८, ९; ७. १५, ११; १६, १०; ३७, २; ८; ८. ६, ४६; ८, १३.

राधानां १. ३०, ५; ३. ५१, १०.

राधाम १. ४१, ७; ८. ७०, १३.

राध्यः १. १५६, १.

राध्यै १. ११६, ११; ८. ९२, २८.

राध्यस्य १०. ७७, ६.

राध्या २. २४, १०.

राध्यानि ४. ११, ३.

रांध्या ६. २३, ६.

रां १०. १११, ७.

रामं १०. ३, ३.

रामीः २. ३४, १२.

रामे १०. ९३, १४.

राम्याः २. २, ८.

राम्याणां ३. ३४, ३; ७. ९, २.

राम्यासु ६. ६५, १.

राय ७. ५५, ३.

रायः १. ३१, १०; ६२, १२; ६८, ५; ९८, ३; १२३, १३; १६७, १; १६९, ५; ३. १६, २; ४. ८, ७; ४१, १०; ४८, १; ५. ४२, ८; ५४, ७; ६. १, ५; १४, ३; १९, ५; ३६, १; ५; ४७, ९; ७. १८, २०; ३४, २२; २३; ३५, २; ३७, ८; ८. ५२, १०; १०. ११७, ५; १४०, ४.

रायः १. ४, १०; १७, ३; २४, ५; ३३, १; ३६, १२; ५१, १४; ७२, ८; ७३, ९; १०; ८१, ७; ९१, २३; ९६, ६; ११३, ४; १२५, १; १२७, ११; १३८, ३; १४९, १; १६६, ३; २. १, १०; २, १२; ९, ५; ११, १२; २४, १५; २७, १७; २८, ११; २९, ७; ४०, ४; ३. २, १५; १६, १; ३; १९, ३; ३०, १८; ३६, १०; ५४, २१; ५६, ६; ४. २, २०; ४, ६; १२, ३; १७, ११; २०, ७; ८; २१, ४; १०; २९, ५; ३३, १०; ३६, ६; ४१, १०; ५. १२, ३; १५, १; ५; २५, ३; ३३, १०; ३६, ४; ४१, ५; ८; ४२, ५; ४९, ४; ५४, १३; ६८, ३; ६. ४, ८; ११, ६; १२, ६; १५, ३; २२, ३; २३, १०; ३६, ४; ४४, २; ४८, ९; ५०, ११; ५४, ८; ५५, २; ३; ७. ४, ६; ७; ८, ३; १८, ३; २०, ९; २८, ५; ३०, १; ३२, १९; ३४, २४; ३७, ५; ४०, ३; ५६, १५; ५७, ६; ६०, ११; ७५, ५; ९३, २; ९५, २; ९७, ४; १००, २; ८. ३, २२; ४, १६; २३, २७; २९; २६, २२; ४६, ६; ४७, ४; ४८, ७; ५१, ६; ५३, १; ५६, २; ५९, ७; ७१, ४; ९२, ९; ९५, ४; ९. ३३, ६; ३५, २; ६१, २६; ८९, ७; ९४, ३; १०. १७, ९; २२, १५; ३०, १२; ३५, ७; ३६, ७; ४३, ३; १४१, २; ६; १४७, ४; ५.

रायःऽकामः १. ७८, २; ७. ३२, ३; ४२, ६.

रायतः १. १८२, ४.

रायसि ७. ५५, ३.

राया १. ४८, १; १६; ५३, ५; ७१, ६; १२९, ९; १०; ३. १६, ६; २३, २; ४. २, ९; ५, १५; ८, ६; ३१, १२; ४२, १०; ५. ३, ६; १०, १; ३०, १; ५०, २; ६. ५, ५; १३, ३; १५, ११; १८, ७; ११; १९, १३; २०, ६; ३५, १; ४९, १३; ७. ४३, ५; ६६, ८; ६७, ९; ७२, ५; ९५, ४; ८. ५, ३२; २४, १५; २६, ७; ४६, ५; ९७, ६; १०. ४२, ९; ९३, १०; १३.

रायां ९. १०८, १३.
राये १. ५, ३; ९, ६; १०, ६; ५४, ११; ७३, ८; ८४, १७; १००, १६; ११३, ५; ११६, ९; १२०, ९; १४२, १०; १८९, १; २. ३, ४; ३. १५, ३; १९, १; ५३, ११; ४. २, ११; ३१, ११; ५. ६, ३; १५, ५; २०, ४; ४१, ११; ४२, १५; १६; ४३, १; ४६, ४; ५०, १; ५; ६४, ६; ६९, ३; ७९, १; ६. १, २; १७, १४; ४५, ३०; ४९, १४; ७. ९, ६; १८, २; ६; २०, ६; २७, ५; ३२, ९; ३४, १८; ८६, ७; ९०, ३[२]; ८. ४, १५; ७, १८; २३, १६; २४, १२; ४८, २; ७१, १४; ९७, १३; १०३, ४; ९. १०, १; ४५, ३; ६३, १६; ६४, ३; ८६, ४५; ९७, ६; १०. ५९, २; ६१, २२; ६३, १५; ७६, २; ११२, १०; ११६, १.
रारंजत् ९. ५, २.
राविषं १०. ८६, ५.
राशयः ८. ९६, ८.
राशिः ६. ५५, ३.
राशिं ४. २०, ८; ९. ८७, ९.
राष्टिं १. १०४, ४.
राष्ट्रं ४. ४२, १; ७. ८४, २; १०. १०९, ३; १२४, ४; १७३, १; २; ५.
राष्ट्रस्य १०. १२४, ५.
राष्ट्राणां ७. ३४, ११.
राष्ट्राय १०. १७४, १.
राष्ट्री ६. ४, ५; ८. १००, १०; १०. १२५, ३.
रासत् ५. २५, १; ६. ५०, ६.
रासत् ६. ४९, ८.
रासतां १०. ३६, १४.
रासते १. ९६, ८; ४. ५५, ८; ७. ४५, ३; ८. १, २२; १०. १२२, १.
रासन् ७. ४०, ६.
रासन् ७. ३४, २२.
रासंतां ७. ३५, १५; १०. ६५, ३.
रासभः १. ११६, २.
रासभं ८. ८५, ७.
रासभस्य १. ३४, ९; १६२, २१; ३. ५३, ५.
रासाथां १. ४६, ६.
रासि २. ११, १४[३].
रासि १. १४०, १२; २. ११, १३; ३३, १२; ३. ४, १; ६. ४, ८; ७. ९५, ६; ९. ९, ९.
रासीय ७. ३२, १८; ८. १९, २६.
रास्पिनस्य १. १२२, ४.
रास्पिरासः ५. ४३, १४.
रास्व १. ११४, ६; ९; ३. ५७, ६; ६२, ४; ४. २, ११; ६. ४८, ४; ७. १६, ४; ८. ४, १६; ६०, ६; ११; ९. ४३, ६; ६१, २६; १०. ७, ७.
रास्व २. २७, १०; ३. १३, ७; ४. ११, २; ५. १३, ५; ७. ७९, ४; ८१, ५; ८. २३, १२; ९८, १२.
रिक्तं ८. ५८, ३.
रिक्थं ३. ३१, २.
रिक्थाः ३. ६, २.
रिख ६. ५३, ७.
रिच्यते ७. ३२, १२; ८. ९२, १४.
रिच्यसे २. १, १५.
रिणक् २. १५, ८.
रिणक् २. १९, ५.
रिणक्ति ७. ७१, १.
रिणन्नाव ८. १००, १२.
रिणते ५. ५८, ६.
रिणन् २. २२, ४; ८. ७, २८; ३२, २; ९. १०९, २२; १०. १३८, १.
रिणंति ९. ७१, ६.
रिणाः ४. १९, ३.
रिणाति १. १६६, ६.
रिणाति १. १२७, ४; १४८, ४; १७९, ४; ५. ३१, ११; ४१, १०; १०. १२०, १.
रिणीते १. १२४, ७; ५. ८०, ६; ९. ७१, २.
रिणीथः १. ११७, ४; १९.
रितः ६. ५७, ४.
रिपः २. ३२, २; ७. ३२, १२; ६०, ९; १०४, १८.
रिपः ३. ५, ५; १०. ७९, ३.
रिपवः १. १४७, ३; १४८, ५; २. २३, १६; ३. ३०, १५; ५. ३, ११.
रिपवे १. १८९, ५; २. २७, १६; ५. १२, ४; ६. ६७, ४; ७. ६५, ३; ८. २२, १४; ६०, ८.
रिपुः १. ३६, १६; २. ३४, ९; ४१, ८; ६. ५१, ७; ७. १०४, १०; ८. २३, १५; १०. १८५, २.
रिपुणा ४. ५८, ५.
रिपुं ५. ७९, ९; ६. ५१, १३; ८. १८, १४; ९. ८३, ४.
रिपूणां ८. ६७, ९.
रिपोः ४. ३, १३; ८. ११, ४.
रिप्रं १. १६२, ९.
रिप्रं ९. ७८, १; १०. १७, १०.
रिप्रऽवाहः १०. १६, ९.
रिभ्यते ७. ७६, ७.
रिरिकांसः १. ७२, ५; ४. २४, ३.
रिरिक्षतः ७. ३६, ४.
रिरिक्षति ८. १८, १३.
रिरिक्षंतं १. १२९, १०.
रिरिक्षे ८. ८८, ५.
रिरिक्षोः १. १८९, ६.
रिरिचथुः ४. २८, ५.
रिरिचाथे इति १. १०९, ६.
रिरिचानः १०. ८९, १.
रिरिचे ६. २१, २.
रिरिचे १. ५९, ५; ६१, ९; १०२, ७; १६४, २५; ३. ४६, ३; ६. २४, ३; ३०, १; ७. ४२, ३; १०. ३२, ५; ८९, ११.
रिरिच्यात् ४. २४, ५.
रिरिच्यां १०. १०, ७.
रिरिभ्रे १०. ७७, ३.
रिरिपुः ५. ८५, ८.
रिरिपः १. १०४, ६; ११४, ७; ८; ७. ४६, ३; ८९, ५; १०. १८, १; १२८, ८.
रिरिषत् ३. ५३, २०.
रिरिषत १. ८९, ९.
रिरिषीष्ट ६. ५१, ७; ८. १८, १३.
रिरिषेः १. १२९, १०.

रिरिन्हांसं १०. ७९, ३.
रिरीहि ६. ३९, ५; ४६, ८; ६५, ६; ९. ११, ९; ९१, ६; १०. ९८, १०; १६९, ३.
रिरेच ४. १६, ६.
रिरेभ १. १२०, ६.
रिशंतां १०. १६९, १.
रिशंतीः ६. २८, ७.
रिशादसः १. १९, ५; २६, ४; ६४, ५; १८६, ८; ६. ५१, ४; ८. २७, ४; १०. ७७, ३; ५.
रिशादसः १. ३९, ४; ५. ६०, ७; ६१, १६; ७. ५९, ९; ८. २७, १०; ३०, २; ८३, ५.
रिशादसं १. २, ७; ५. ६४, १; ७. ६६, ७.
रिशादसा ५. ६६, १.
रिशादसा ५. ६७, २; ७१, १; ८. ८, १७.
रिशादाः १. ७७, ४; ९. ६९, १०.
रिषः १.४१, २; ९८, २; २. २६, ४; ३४, ९; ३५, ६; ३. ३१, २०; ५. ५२, ४; ६७, ३; ६. २४, १०[२]; ६३, २; १०. ३६, २.
रिषण्यः २. ११, १; ७. ९, ५; १०. २२, १५.
रिषण्यत ८. १, १; २०, १.
रिषण्यति २. २३, १२.
रिषण्यवः १. १४८, ५.
रिषत् ६. ५४, ७; ८. ६५, १०; ६७, ११; १०. ६२, ११; ९७, २०.
रिषंतः १. १२, ५; ३६, १५; ७. १५, १३; ८. ४४, ११.
रिषंते १. १८९, ५; ५. ३, १२.
रिषन् ८. १०३, १३.
रिषंतं २. ३०, ९.
रिषं १०. १८, १३.
रिषयध्यै १. १२९, ८.
रिषाथ ७. ३३, ४.
रिषाथन १०. ४८, ५; ९४, १०.
रिषाम १. ९४, १–१४; ४. १२, ५; ६. ४४, ११; १०. १७८, २.
रिषे ५. ४१, १६.

रिष्टं १. १३१, ७; ९. ११२, १.
रिष्यति १. १८, ४; ५. ४४, ९; ५४, ७; ६. ५४, ३.
रिष्यथ ५. ५४, ४.
रिष्यंति १०. १०७, ८.
रिष्यसि १. १६२, २१; ८. ३१, १६.
रिष्याः १०. ५१, ७.
रिष्याति १०. ९७, १७.
रिष्येत् ८. ४८, १०.
रिष्येत् १. ९१, ८.
रिष्येम ६. ५४, ९.
रिहती ३. ५५, १३.
रिहते ८. २०, २१.
रिहन् १. १४०, ९.
रिहंति १. १४६, २; ३. ४१, ५; १०. १२३, ३.
रिहंति १. २२, १४; १८६, ७; २. ३५, १३; ९. ८५, ११; ८६, ३१; ४३; ४६; ९७, ५७; १००, १; ७; १०. १२३, १.
रिहाणे इति ३. ३३, १; ७. २, ५.
रीतिऽआपः ९. १०६, ९.
रीतिऽआपा ५. ६८, ५.
रीतिः २. २४, १४; ३९, ५; ६. १३, १.
रीतिं ५. ४८, ४; ९. १०८, १०.
रीयंते १. १३५, ७; ५. ७, ८.
रीयते १. ३०, २; ८५, ३; १०. ५३, ८.
रीयंते १०. ४०, ९.
रीरध १०. ३०, १.
रीरधः १. २५, २; २. ३२, २; ३. १६, ५; ८. ६०, ८.
रीरधत् २. ३३, ५.
रीरधत ६. ५१, ६.
रीरधतं ७. ९४, ३; ८. ८, १३.
रीरमत् ४. १७, १४; ५. ५३, ९; ७. ३२, १०; १०. ९२, ८.
रीरमन् २. १८, ३; ७. ३२, १; १०. १६०, १.
रीरमाम १. १६५, २.
रुक्मः १. ८८, २; ९६, ५; ४. १०, ५; ६; ६. ५१, १; ७. ३, ६; ६३, ४; १०. ४५, ८.
रुक्मःऽइव ५. ६१, १२.

रुक्मं १. ११७, ५; ५. १, १२.
रुक्मऽवक्षसः २. ३४, ८; ५. ५५, १; ५७, ५; १०. ७८, २.
रुक्मऽवक्षसः २. ३४, २; ८. २०, २२.
रुक्माः १. १६६, १०; ५. ५४, ११; ७. ५६, १३.
रुक्मान् १. ६४, ४.
रुक्मासः ८. २०, ११.
रुक्मिऽभिः ९. १५, ५.
रुक्मी १. ६६, ३.
रुक्मेभिः ५. ५६, १.
रुक्मेषु ५. ५३, ४.
रुक्मैः ५. ५२, ६; ७. ५७, ३.
रुक्षः ६. ३, ७.
रुग्णं ३. ३१, ६.
रुचः ९. ९, ८; ४९, ५; ९६, २४; १०. १८८, ३.
रुचयत ३. ६, ७.
रुचा ४. ५६, १; ९. ६४, १३; २८; ६५, २७; १११, १; १०. १०६, ४.
रुचानः ३. १५, ६; ६. ३९, ४; ७. ६९, १; १०. ४५, ८.
रुचानाः ४. ५१, ९; ७. ५६, १३.
रुचाऽरुचा ९. ६५, २.
रुचे ९. २३, २; १०५, ५.
रुज ९. ५३, ३; ९१, ४.
रुज १. १०२, ४; ३. ३०, १६; ४. ३, १४; ८. ७३, १८; ९. १०८, ६; १०. ८७, २५; १५२, ३.
रुजः ६. २२, ६.
रुजत् ६. ३२, २; ३९, २; ७. ७५, ७; ९. ३४, १.
रुजति १०. ८९, ६.
रुजन् ४. १६, ८; ८. ६, १३; १०. ८४, ३; १६८, १.
रुजन् १. ७१, २.
रुजंतः ६. ६, ३.
रुजंति ४. १८, ६; ५. २, १०.
रुजानाः १. ३२, ६.
रुजामि ४. ४, ११.
रुजेम ४. २, १५.
रुणद्धि १०. ३४, ३; ४२, ९.
रुणधामहै १. ८, २.

रुणध्मि १०. ३४, १२.
रुतं ९. ११२, १.
रुतस्यं १०. ३९, ३.
रुदतः १. ३३, ७.
रुदंति १०. ४०, १०.
रुद्रं ५. ३, ३.
रुद्र १. ११४, २; ३; ७; ८; २. ३३, १–४; ७; १०–१२; १५; ७. ४६, २; ४; १०. १६९, १.
रुद्रः १. ४३, ३; ११४, ११; २. १, ६; ३४, २; ३८, ९; ५. ४६, २; ५१, १३; ६०, ५; ६. ५०, १२; ७. ३५, ६; ४०, ५; १०. ६५, १; ६६, ३; ९३, ४.
रुद्रं १. ४३, ४; ११४, ४; २. ३३, ५; ३. २, ५; ४. ३, १; ५. ४२, ११; ५२, १६; ६. ४९, १०[२]; ७. १०, ४; ४१, १; ८. ७२, ३; १०. ६४, ८; १२६, ५.
रुद्रवर्तनी इति रुद्रऽवर्तनी ८. २२, १४.
रुद्रवर्तनी इति रुद्रऽवर्तनी १. ३, ३; ८. २२, १; १०. ३९, ११.
रुद्रस्यं १. ६४, २; १२; ८५, १; २. ३३, ६; ८; १३; १४; ५. ४२, १५; ५९, ८; ६. २८, ७; ५०, ४; ६६, ३; ११; ७. ५६, १; ५८, ५; ८. १३, २०; २०, १७.
रुद्रा ५. ७३, ८; ७५, ३.
रुद्रा १. १५८, १; १०. ९३, ७.
रुद्रा २. ४१, ७; ५. ७०, २; ३; ८. २६, ५.
रुद्राः १. ३९, ७; ८. ७, १२; १०. ६६, १२.
रुद्राः १. ६४, ३; १६६, २; २. ३४, १३; ३. ८, ८; ५. ६०, २; ८. ३, ७; ५४, ३; ६३, १२; १०. ९२, ६; १२८, ९.
रुद्राः २. ३४, ९; ५. ५४, ४; ६०, ६.
रुद्राणां १. १०१, ७; ८. १०१, १५; १०. ६४, ११.
रुद्रात् २. ३३, ९.
रुद्रान् १. ४५, १; ३. २०, ५; १०. ६६, ४.
रुद्रायं १. २७, १०; ४३, १; ११४, १; ६; १२२, १; १२९, ३; ४. ३, ६; ७; ५. ४१, २; ७. ३६, ५; ४६, १; १०. ९२, ९; १२५, ६.
रुद्रासः १. ३९, ४.
रुद्रासः १. ८५, २; ५. ८७, ७; ८. १३, २८; ९. ७३, ७.
रुद्रासः ५. ५७, १; ८. २०, २.
रुद्रियं १. ४३, २; ७. ४०, ५; १०. ६४, ८.
रुद्रिया १. ७२, ४.
रुद्रियाः ३. २६, ५.
रुद्रियाः २. ३४, १०.
रुद्रियाणां ८. २०, ३; १०. ४८, ११.
रुद्रियाय ५. ४१, ११.
रुद्रियासः १. ३८, ७; ५. ५८, ७.
रुद्रियासः ५. ५७, ७; ६. ६२, ८; ७. ५६, २२.
रुद्रियेषु २. ११, ३.
रुद्रेणं १०. ९२, ५; १३६, ७.
रुद्रेभिः १. ५८, ३; १००, ५; १०१, ७; ३. ३२, ३; ७. ५, ९; १०, ४; ३५, ६; ८. १०३, १४; १०. ३२, ५; ६६, ३; ९९, ५; १२५, १.
रुद्रेषुं १०. ६४, ८.
रुद्रैः २. ३१, १; ३. ३२, २; ८. ३५, १; १०. १५०, १.
रुद्रौ ८. २२, १४.
रुधत् १०. १०५, १.
रुधतः १. १७९, ४.
रुधिऽक्रां २. १४, ५.
रुध्यसे ८. ४३, ९.
रुपः ४. ५, ७; ८; १०. १३, ३.
रुमें ८. ४, २.
रुरुक्कान् १. १४९, ३.
रुरुक्षणिं ९. ४८, २.
रुरुचंत ४. ५५, २.
रुरुचानं ३. २, ३.
रुरुचुः ४. १६, ४; ६. ६२, २; ८. ३, २०; १०. १२२, ५.
रुरुचे ६. १५, ५.
रुरुचे ३. ६१, ५; ७. ७७, १.
रुरुच्याः ६. ३५, ४.
रुरुध्रे १०. ८४, ३.
रुरुऽशीर्ष्णी ६. ७५, १५.
रुरुहुः ५. ७, ५; ६. ७, ६; २४, ३; ९. ७९, ४.
रुरोच ४. ५, १५.
रुरोजं ६. १८, १०; १०. ८९, ७.
रुरोज ४. ५०, ५; ६. ३२, ३.
रुरोजिंथ ६. १६, ३९.
रुरोजिथ ८. ६४, ५.
रुरोधिथ १. १०२, १०.
रुव १. १०, ४.
रुवण्यः ८. ९६, १२.
रुवण्युं १. १२२, ५.
रुवत् १. १७३, ३; ४. ५६, १.
रुवतिं ९. ७०, ७.
रुवंतं ५. ४२, १४.
रुशत् १. ६२, ९; ९२, ५; ११५, ५; ३. २९, ३; ४. ५, १५; ११, १; ५. १, २; ५४, १२; ६. ७२, ४; ७. ७७, २; ८. ९३, १३; ९. ९१, ३; १०. ३१, ११; ४९, १०.
रुशतः १. १८१, ८; ४. ७, ९.
रुशता ४. ३, ९; ६. ६५, १; ९. ६९, ५; १०. १, १.
रुशती १. ११३, २; १०. ७५, ७; ८५, ३०.
रुशतीं १. ११७, ८; १०. ३, १.
रुशत्ऽऊर्मे १. ५८, ४.
रुशत्ऽगावि ५. ६४, ७.
रुशत्ऽपशुः ५. ७५, ९.
रुशत्ऽभिः १. ६२, ८; ४. ५१, ९; १०. ३, ३; ६.
रुशत्ऽवत्सा १. ११३, २.
रुशन् ८. ७२, ५.
रुशंतः १. ४८, १३; ६. ६४, १; ३; ८. १, ३३.
रुशंतं १. ९२, २; ६. १, ३; ६, १; ९. ९७, १५; १०. १, ५.
रुशमं ८. ३, १२.
रुशमाः ५. ३०, १२.
रुशमानां ५. ३०, १४.
रुशमासः ५. ३०, १३.
रुशमे ८. ४, २; ५१, ९.

रुशमेषु ५. ३०, १५.
रुहः १०. ९७, २.
रुहत् ५. ३६, २.
रुहत १. ३४, ५; ९. ४०, २.
रुहतं ८. २२, ९.
रुहं ८. १, ३१.
रुहाणाः १. ३२, ८.
रुहाव ७. ८८, ३.
रुहेम ३. ८, ११; ८. ४२, ३; १०. ६३, १०; १४; १७८, २.
रूपं १. ७१, १०; ९५, ८; ११४, ५; ११५, ५; १६३, ७; १६४, ४४; ३. ३८, ७; ६. ४७, १८; ७. ९७, ६; ८. ४१, ५; ९. ६५, १८; ६८, ६; ७१, ८; ७४, ७; ९७, ५७; १०. १२३, ४; १२४, ७; १६८, ४.
रूपंऽरूपं ३. ५३, ८; ६. ४७, १८.
रूपऽशः १. १६४, १५.
रूपा २. १३, ३; ५. ४२, १३; ८. १०१, १३; ९. ६४, ८; ८५, १२; १११, १; १०. ९६, ३; १३९, ३.
रूपाऽइव ८. १०२, ८.
रूपाणि १. १०८, ५; १८८, ९; ५. ५२, ११; ८१, २; ७. ५५, १; ८. १५, १३; ९. २५, ४; १०. २१, ३; ८५, ३५; १६९, ३; १८४, १.
रूपे १. १६४, ६; ४. ११, १; ९. १६, ६.
रूपेभिः ५. ४३, १०.
रूपैः १. १६०, २; ९. ३४, ४; १०. ११०, ९; ११२, ३.
रेकुं ४. ५, १२; १०. १०८, ७.
रेक्णः १. ३१, १४; १२१, ५; १५८, १; ६. २०, ७; ७. ४, ७; ४०, २; ८. ४, १८; ४६, १५; १०. १३२, ३^{२}.
रेक्णसा १. १६२, २.
रेक्णस्वती १०. ६३, १६.
रेचि ४. १६, ५.
रेजत ४. १७, २.
रेजत ४. १७, २; २२, ४; ५. ६०, ३.

रेजति १. १२९, ६^{२}; १६८, ५.
रेजंते १. ३७, ८; ६. ६६, ९; १०. १४७, १.
रेजते १. ८०, १४; ८७, ३; ५. ४४, ९; ६०, २; ८. २०, ५.
रेजथ ५. ५९, ४.
रेजंत ८. १०३, ३.
रेजंते ७. २१, ३.
रेजंते १. १४३, ३; १६४, १५; ६. ५०, ५.
रेजमानः १. १७१, ४; ३. ३१, ३.
रेजमानं १०. ६, ५.
रेजमानाः ७. ६०, १०.
रेजमानान् १०. ४४, ८.
रेजमाने इति १०. १२१, ६.
रेजयत् ४. २२, ३; ५. ८७, ५; १०. ६१, १६.
रेजयति ८. ६६, ३.
रेजयंति ७. ५७, १.
रेजेते इति ८. ९७, १४.
रेणुः १. ३३, १४; १०. ७२, ६.
रेणुऽकंकाटः ६. २८, ४.
रेणुं १. ५६, ४; ४. १७, १३; ३८, ६; ७; ४२, ५; १०. १६८, १.
रेतः १. ६८, ४; ७१, ८; १२८, ३^{२}; १६४, ३४–३६; ३. ५५, १७; ४. ३, ७; ५. ८३, १; ६. ७०, २; ७. ३३, ७; १३; ६७, ६; ९. ६०, ४; ९९, ६; १०. ६१, २; ६; ७; ११; ९४, ५; १२९, ४.
रेतःऽधाः ३. ५६, ३; ५. ६९, २; ७. १०१, ६; ९. ८६, ३९; १०. १२९, ५.
रेतसः १. १००, ३; ३. ३१, १०; ८. ६, ३०; ९. ८६, २८.
रेतसा ५. १७, ३; ८३, ४; ९. ७४, १.
रेतसि ६. २८, ८; ९. १९, ४.
रेतसे १. १५५, ३.
रेतांसि ८. ४४, १६; १०. ६४, १४.
रेतिनः १०. ४०, ११.
रेपः ४. ६, ६.
रेभः १. ११३, १७; १२७, १०; ६. ३, ६; ११, ३; ९. ७, ६; ६६, ९; ७१, ७; ८६, ३१.

रेभत् १०. ९२, १५.
रेभतः ८. ३७, ७; ४४, २०.
रेभति १. १०५, ९.
रेभत्ऽभिः १०. ३, ६.
रेभन् ७. १८, २२; ९. ९६, ६; १७; ९७, १; ७; ४७; १०६, १४.
रेभंतः १०. ६१, २४.
रेभंति ९. ९७, ५७.
रेभं १. ११२, ५; ११६, २४; ११७, ४; ११८, ६; ११९, ६; १०. ३९, ९.
रेभाः १. १६३, १२; १०. ७१, ३; ८७, १३.
रेभासः ८. ९७, ११.
रेभिरे १. १४०, ८.
रेभे १०. ८७, १२.
रेभैः ७. ६३, ३.
रेरिहत् १. १४०, ९; ४. ३८, ६; १०. ४५, ४.
रेरिहाणा ३. ५५, १४; ६. २७, ७.
रेरिह्यते १०. ४, ४.
रेळिह १०. ११४, ४^{२}.
रेवत् १. ७९, ५; ९२, १४; ९५, ११; ९६, ९; ११६, १८; १२४, ९; १०^{२}; १५१, ८; ९^{२}; २. २, ६; ९, ६; ३५, ४; ३. ७, १०; १८, ४; ५; २३, २; ४; ४. ५१, ४; ५. २३, ४; ६. ४८, ७; १०. ३५, ४; ६९, ३; ७७, ७.
रेवतः १. ४, २; १२०, १२; ६. ४४, ११; ७. ४२, ४; ८. २, १३; ४७, ९; १०. २२, १५; ३६, ३.
रेवता ४. २५, ७.
रेवति १०. ८६, १३.
रेवति ५. ५१, १४.
रेवतीं ३. ६१, ६; १०. ३५, ४.
रेवतीः १. ३०, १३; १५८, २; ९. ७२, ९; १०. ३०, १४.
रेवतीः ४. ५१, ४; १०. १९, १; ३०, ८; १२.
रेवतीनां १०. १८०, १.
रेवते १०. ११६, २.
रेवत्ऽभिः ६. १, ११.

रे॒वंतं॑ ८. २, ११; २१, १४.

रे॒वान् १. १८, २; २. २७, १२; ७. १, २३; ८. २, १३; ४५, १५; ९६, १९; १०. ६०, ४; १६०, ४.

रे॒वान्ऽइ॑व १. २७, १२; ८. ४८, ६.

रे॒प॒णाः १. १४८, ५.

रे॒प॒त् ७. २०, ६.

रे॒पयं॑ति १. १४८, ५.

रैभी॑ १०. ८५, ६.

रै॒व॒तासः॑ ५. ६०, ४.

रै॒व॒त्याऽइ॑व १०. ९४, १०.

रोकः॑ ६. ६६, ६.

रो॒काः ३. ६, ७.

रोच॑त ४. १, १७.

रो॒च॒त ४. १०, ६.

रो॒च॒तां १०. ४३, ९.

रोचं॑ते १. ४३, ५; १४०, ११; ३. ५५, ११; ७. ८, ४; १०. ६५, ५.

रो॒च॒ते १. ५८, २; १४८, ४; १८८, ११; ३. २९, ६; ७; ४. १०, ५; ११, १; ८. ४३, ८; १०; ४४, २१; ९. २, ६; १११, १; १०. ६९, २; ११८, ३.

रो॒च॒नं १. ४९, ४; ५०, ४; ३. ४४, ४; ८. ९८, ३.

रो॒च॒न॒ऽस्थाः ६. ६, २.

रो॒च॒न॒ऽस्थां ३. २, १४.

रो॒च॒नस्य॑ ५. ६९, ४; १०. ४६, ३.

रो॒च॒ना १. ६, १; ८१, ५; १०२, ८; १४६, १; २. २७, ९; ३. १२, ९; ६१, ५; ४. ५३, ५; ५. २९, १; ६९, १; ८१, ४; ६. ७, ७; ८. ५, ८; १४, ७; ९; ९३, २६; ९४, ९; ९. १७, ५; ३७, ३; ४२, १; ८५, ९; १०. ३२, २; ४९, ६; ६५, ४; ८९, १; १८९, २.

रो॒च॒नात् १. ६, ९; १४, ९; ४९, १; ८. १, १८; ८, ७.

रो॒च॒नानां॑ ७. ५, १०.

रो॒च॒नानि॑ १. ९३, ५; १४९, ४; ३. ५६, ८.

रो॒च॒ने १. १९, ६; १०५, ५; १५५, ३; ३. ६, ८; २२, ३; ८. १०, १; ६९, ३; ८२, ४; ९७, ५; ९. ७५, २; ८६, २७.

रो॒च॒नेन॑ ३. ५५, ९; ६. १, ७; १०. ४, २; ८८, ५.

रो॒च॒नेषु॑ ६. ४४, २३.

रोचं॑ते १. ६, १.

रो॒चं॒ते ८. ५५, २.

रोच॑मानः ३. ४६, ३; ७. ३, ९; ६२, १; ९. १११, २; १०. ११८, ४.

रोच॑मानस्य १०. ३, ५.

रोच॑माना ६. ६४, २.

रोच॑मानाः १. १६५, १२; ३. ७, ५; ४. १४, १; ६. ६४, १.

रोच॑मानां १. ११५, २.

रो॒च॒य ९. ९, ८; ३६, ३.

रो॒च॒य॒त् ३. २, २; ६. ३९, ४; ९. ८६, २१.

रो॒चय॑न् ९. ४९, ५.

रोचं॑से ६. २, ६; ७. ३, ६.

रो॒च॒से १. ९४, ७; २. ७, ४; ८. ९, १८.

रो॒चि॒ १. १२१, ६.

रो॒चिषा॑ ५. २६, १.

रो॒द॒सि॒ऽप्राः १०. ८८, ५.

रो॒द॒सि॒ऽप्रां १०. ८८, १०.

रो॒द॒सी १. १६७, ५; ५. ५६, ८; ६. ५०, ५; ६६, ६.

रोदं॑स॒ी इतिं॑ १. १०, ८; ३१, ३; ३३, ९; ३६, ८; ५१, १०; ५४, २; ५९, ४; ६२, ७; ६४, ९; ७२, ४; ७३, ८; ७६, २; ८५, १; १००, १४; १३३, १; १३४, ३; १५१, १; १६०, २; ४; १७३, ३; ६; १८५, ४; १८६, ८; २. १, १५; २, ५; ६; ११, ९; १२, १; १५, २; १७, ४; २२, २; ३१, ४; ३. २, २; ७; ३, २; ४; १०; ६, २; ५; १०; ७, ४; ९; १३, २; १५, ५; ३०, ५; ३१, १०; ३२, ७; ३४, १; ३८, ३; ८; ३९, ८; ४९, ३; ५३, १२; ५४, १५; ५६, १; ७; ५७, ४; ६१, ६; ७; ४. ७, ८; १६, ५; १८, ५; १९, १; ३४, ९; ४२, ३; ५. १, ७; १६, ४; २९, ४; ३०, ८; ३१, ६; ४२, १४; ४६, ८; ५३, ६; ६१, १२; ८५, ३; ६. १, ११; ३, ७; ४, ६; ८, ३; ११, ४; १२, १; १५, १५; १६, २४; १७, ७; २९, ५; ३०, १; ४४, ५; ४६, ५; ४८, ६; ५२, १४; ६६, ६; ७; ६७, ५; ७०, ६; ७३, १; ७. २, ३; ५, ४; १२, १; १३, २; १८, २४; २०, ४; २३, ३; २८, ३; ३१, ७; ३४, २२–२४; ३५, ३; ३९, ७; ४०, २; ५६, १७; ५७, १; ३; ५८, १; ६१, ४; ६९, १; ७२, ३; ७९, १; ८६, १; ८७, २; ३; ९०, ३; ९६, १; ९७, ८; ९९, ३; ८. ३, ६; ६, ५; १७; ३८; ७, १६; १०, ६; १२, ७; २४; १५, २; २०, ४; २५, १८; २१; ४१, १०; ६४, ४; ७०, ५; ७३, १३; ९३, १२; ९४, ११; ९८, ५; ९. १८, ५; ६; ४१, ५; ७०, ५; ७४, २; ७५, ४; ७६, ३; ८५, १२; ८६, १३; ९७, २७; ३८; १०१, ७; १५; ११०, ९; १०. ५, ४; ११, ९; ४५, ४; ५०, १; ५४, १; ५५, ३; ५९, ८; ६५, ५; ७६, १; ८०, १; २; ८८, ३; ८९, १३; ९३, १; ९६, ११; ११२, ४; ११९, ७; १३४, १; १३६, १; १३९, २; १४०, २; १४७, १.

रो॒द॒सी इतिं॑ १. १६७, ४; १०. ९२, ११.

रो॒द॒सी॒ इति॑ १. ५२, १०; १०५, १–१८; १८५, ३; ३. २६, ९; ५४, ३; ४; १०; ४. ५५, ६; ५६, ४; ६. ५०, ३; ६२, ८; ७०, २; ३; ९. ७, ९; ९८, ९; १०. १२, ४; ६७, ११; ७९, ४.

रोदं॑सीभ्यां १. १३६, ६.

रोदं॑सोः ९. २२, ५.

रोदं॑स्योः १. ३३, ५; ५९, २; ९६, ४; ११७, १०; १२२, १; १४९, २; १५१, ३; १६८, १; ३. ३१, १३; ४. ३, १; ६. २, ११; १६, ४६; २४, ३; ७. ६, २; ६; ८.

७२, १३; ९. ९०, १; १०. १, २; ७४, १.
रोधः ४. ५, १; १०. ४८, २.
रोधऽचक्राः १. १९०, ७.
रोधत् १. ६७, ५.
रोधति ८. ४३, ६.
रोधना १. १२१, ७.
रोधनाः २. १३, १०.
रोधस्वतीः १. ३८, ११.
रोधांसि २. १५, ८; ४. २२, ४.
रोपणाकासु १. ५०, १२.
रोपुषीणां १. १९१, १३.
रोम १. ६५, ४; ९. ९७, ११.
रोमण्ऽवंतौ ९. ११२, ४.
रोमशं ८. ३१, ९; १०. ८६, १६.
रोमशा १. १२६, ७; ८. ९१, ६.
रोमाणि १. १३५, ६; ९. ६२, ८; ७५, ४.
रोरवीति ३. ५५, १७.
रोरवीति ४. ५८, ३; ६. ७३, १; ७. १०१, १.
रोरुचानः ४. १, ७.
रोरुवत् १. ५४, १; ५; १४०, ६; ६. ६१, ८; ९. ६५, १९; ६८, २; ७१, २; ८५, ९; ८६, ७; ९१, ३; १०. २८, २; ७५, ३; ८६, १५; ९२, ५.
रोषति ८. ४, ८; ९९, ४.
रोह १. ५६, २; ३. ८, ११; ९. ६३, २२; १०. ८५, २०.
रोहत १०. १८, ६.
रोहति १. १४१, ४; ८. ४१, ८.
रोहतु १०. १६, १३; ६२, ८.
रोहते २. ५, ४; ८. १३, ६.
रोहथः ५. ६२, ८.
रोहन् ९. १७, ५.
रोहनं १. ५२, ९.
रोहंति ६. ४४, ६.
रोहंतु १०. १८, ७; १४२, ८.
रोहय ८. ९१, ५.
रोहयः ८. ८९, ७; ९. १०७, ७; १०. १५६, ४.
रोहयत् १. ७, ३.
रोहयंतः १०. ६५, ११.
रोहसि ९. ३६, ६; ८०, २.
रोहसे १. ५१, १२.
रोहांसि ६. ७१, ५.
रोहिणीषु १. ६२, ९; ८. ९३, १३.
रोहिण्या ८. १०१, १३.
रोहित् १. १००, १६.
रोहितः १. ३९, ६; ८. ७, २८.
रोहितः १. १४, १२; ५. ५६, ६; ७. ४२, २.
रोहितं ८. ३, २२.
रोहित्ऽअश्व ८. ४३, १६.
रोहित्ऽअश्व १. ४५, २; १०. ९८, ९.
रोहित्ऽअश्वः ४. १, ८; १०. ७, ४.
रोहितस्य ८. ३, २४.
रोहिता १. ९४, १०; १३४, ३; २. १०, २; ३. ६, ६; ४. २, ३; ५. ६१, ९; ८. ६८, १५; १०. ६०, ६.
रोहितासः ४. ६, ९.
रोहितौ ५. ३६, ६.
रौद्रः १०. ३, १.
रौद्रं १०. ६१, १.
रौद्रौ १०. ६१, १५.
रौहिणं १. १०३, २; २. १२, १२.

ल

लक्षं २. १२, ४.
लक्ष्मण्यस्य ५. ३३, १०.
लक्ष्मीः १०. ७१, २.
लयंतां १०. ८४, ७.
ललामीः १. १००, १६.
लांगलं ४. ५७, ४.
लायं १०. ४२, १.
लिबुजाऽइव १०. १०, १३.
लोकः ३. ३७, ११.
लोकऽकृत् ९. ८६, २१; १०. १३३, १.
लोकऽकृत्नुं ८. १५, ४; ९. २, ८.
लोकं १. ९३, ६; २. ३०, ६; ३. २, ९; ४. १७, १७; ५. ४, ११; ६. २३, ३; ७; ४७, ८; ७३, २; ७. २०, २; ३३, ५; ६०, ९; ८४, २; ९९, ४; ८. १००, १२; ९. ९२, ५; १०. १३, २; १४, ९; १६, ४; ३०, ७; ८५, २०; १०४, १०; १८०, ३.
लोकाः ९. ११३, ९.
लोकान् १०. ९०, १४.
लोके ३. २९, ८; ५. १, ६; ९. ११३, ७^{2}; १०. ८५, २४.
लोगं १०. १८, १३.
लोगेन १०. २८, ९.
लोधं ३. ५३, २३.
लोपामुद्रा १. १७९, ४.
लोपाशः १०. २८, ४.
लोमऽभ्यः १०. १६३, ५.
लोम्नःऽलोम्नः १०. १६३, ६.

व

वंशंऽइव १. १०, १.
वंसगः १. ७, ८; ५५, १; ५८, ५; १३०, २^{2}; ५. ३६, १; ६. १६, ३९; ८. ३३, २; १०. १४४, ३.
वंसगं १०. १०२, ७.
वंसगाऽइव १०. १०६, ५.
वंसत् ६. ६८, ५.
वंसत् १०. २६, २.
वंसते ८. १०३, ९.
वंसाम ६. १९, ८; ८. ६०, १२.
वंसि ५. ७०, १.
वंसीमहि ६. १९, १०.
वंसु ९. ५७, ३; ८६, ३५.
वंस्व १. ४८, ११; ७. १७, ५; ८. २३, २७^{2}; ६०, १४.
वंस्व ६. ४८, ४.
वः १. ७, १०; १४, ४; २०, ५; ३०, १; ३६, १; ३७, १; ४; ६; ७; १२; १४; १५; ३८, २^{2}; ३–५; १२; ३९, २; ४; ६; ७; ४०, २; ६; ४१, ४; ५; ८^{2}; ६२, २; ५; ६३, ५; ६४, ९; १३; ६६, ५; ८५, ६^{2}; १२; ८७, २; ८८, ३–६; ९५, ४; १०५, १; ५^{3}; ६; १०७, १; ११०, ३; १२२, १; ४; ५^{3}; १२६, ५; १२७, १०; १२९, ४; ८; १३९, ८^{2}; १४३, ७; १५५, १; १६१, २^{3}; ३; १२^{2}; १६५, ६; १३–१५; १६६, ४^{2}; ५; ६; ९^{3};

१२[२]; १३; १५; १६७, ६; ९; ११; १६८, १[३]; ५; ७[२]; १०; १७१, १; १७२, १; २; १८६, ३; ४; ११; १८८, ८; १९१, ६; ७; **२.** ४, १; १४, ९; ११; १६, १; २४, ५; २७, ५; ६; ८; १४; १६; २९, १[२]; ३–६; ३०, ११; ३१, ६; ७; ३३, १३; ३४, २; १०; ११; १५; ४१, १४; **३.** ८, ६; १३, १; ३; २७, १; ३३, ९; ११; १३; ५४, १७; ५७, २; ६०, १; ४; ६१, ५[२]; **४.** ३, १; ८, १; १६, १६; ३३, ५; ११; ३४, १[२]; २; ३[२]; ४[२]; ५; ११; ३५, १[२]; ६; ९; ३६, १–४; ७[२]; ३७, २[२]; ३[२]; ४; ५१, ४; १०; ११; ५५, १[२]; **५.** ७, १; १८, ३; २१, ४; २५, १; ३९, ४; ४१, ५[२]; ६; ८; १३; १७[२]; १८; ४२, १०; ४४, ४; १२; ४५, ४; ११; ४९, १; ५२, ४; ५३, ९[४]; १०; ११; १३; ५४, २; ५; १०; ११; १५; ५५, ४; ५; ७; ५६, ३; ७; ९; ५७, १; ३; ६[४]; ७; ५८, ३; ५९, १; ४; ६०, २; ३; ६१, २; ६४, १; ६८, १; ८७, १; २; ५; ६; **६.** ५, १; १०, १; १५, १; ४; ६[३]; १६, २२; १९, ४; २२, ७; २३, ९; २८, ६; ७[२]; २९, १; ३८, ३; ४४, ४; ६; ४५, २२; ४८, १; १४; ५०, १; ५१, ३; ७; ९[२]; ५२, ८; १४[२]; ६५, ४; ६६, ७; ६७, १; **७.** २, ३; ३, १; ७; ४, १; ७, १; ९, ४; १६, १; ११[२]; ३१, १; ३२, २०; ३३, ३; ४; ८; १४; ३४, ९[२]; ३६, ८; ९; ३७, १; ४२, ३; ४३, १; ४; ४४, १; ४७, १[२]; २[२]; ४८, १; २; ५२, २; ५६, ७–१०; १२–१४; १७; १८[२]; २१[२]; २३; २४; ५७, १; ५९, ५; ११; ६६, १२; १३; **८.** ७, १; ५; ११; १९–२१; ३१; १२, १९; १८, १९[२]; १९, ७; ३५; २०, ५; ६; ९; १२; १५; १६; २२[२]; २१, ९; २३, ७[२]; २४, १; १८; २५, १६; २७, ६; ७; १०; ११[२]; १२; १५[२]; २०; ३०, १; ३२, ४; २७; ४५, २८; ४६, १४; १७; ४७, १[३]; ६; ४९, १; ५०, ४; ६०, १७; ६६, १; १५; ६७, ६; १६; ६८, ४; ६९, १[२]; २[२]; ७०, ८; ७१, २; १२; ७४, १[२]; ८०, १०; ८३, ६; ९; ८४, १; ८८, १; ८९, ३; ९२, १; ७; ९३, १६; ९४, ८; १०; ९६, १४; ९७, १२; ९९, ७; १००, ७; १०२, ७; **९.** ८६, १७; ९८, ८; १०१, १; ४; १०५, १; **१०.** २, ४; ९, २; ३; १५, ४; १६, १०; १८, ६; १९, ७; २१, १; ३०, ३; ७[२]; ८; ३२, ५[२]; ९; ३४, १२; १४; ३५, १४; ३६, १०; ३७, १२; ५२, १[२]; ५[२]; ६२, १; ४; ६३, २[२]; ६[२]; ११; १७; ६६, १२; ७०, ८; ७२, ६; ७५, १; ७६, १; ५; ८[२]; ७७, ४; ७८, ८; ८८, १८[२]; ९२, १; ९; ९४, १०; १२; ९७, २[२]; ४; ५[२]; ९; १४; २०[२]; १००, ७; १०१, १; ८[२]; ९; १०३, १३[२]; १०६, ४; १०८, २; ६[३]; १११, ८; ११५, ३; १६६, ३; ४[३]; ५[२]; १७५, १; ४; १९१, २; ३[२]; ४[४].

वृक्करि **१०.** ६१, १२.

वर्क्कवे **७.** ३१, ५.

वृक्का **७.** १०४, ८; **८.** ३२, १५; **९.** ७५, २.

वक्त्वानां **३.** २६, ९.

वक्त्वानि **६.** ९, २; ३.

वक्मनि **१.** १३२, २.

वक्मराजेऽसत्याः **६.** ५१, १०.

वक्म्यः **१.** १६७, ७.

वर्क्करी **१.** १४४, ६; **६.** २२, ५.

वर्क्का **१.** १४१, ७; **९.** ९१, १.

वर्क्काः **४.** १९, ७; **१०.** १४८, ५.

वर्क्षः **१.** ९२, ४; १२४, ४; **५.** ३३, २; **६.** ६४, २; **१०.** ४८, २.

वर्क्षःऽसु **१.** ६४, ४; १६६, १०; **५.** ५४, ११; **७.** ५६, १३.

वृक्षणा **५.** ५२, १५.

वृक्षणाः **१.** ३२, १; १६२, ५; **३.** ३३, १२.

वक्षणानि **६.** २३, ६.

वृक्षणाभ्यः **१.** १३४, ४; **८.** १, १७.

वृक्षणासु **३.** ३०, १४; **५.** ४२, १३; **६.** ७२, ४; **१०.** २७, १६; २८, ८; ४९, १०.

वृक्षणिः **८.** ६३, ४.

वक्षणीः **१०.** ६४, ९.

वृक्षणेऽस्थाः **५.** १९, ५.

वक्षत् **१०.** ६१, २३.

वृक्षत् **१.** १३५, ४; १५७, ३; **३.** ५, ९; **६.** २२, ७; **८.** ३४, ८; **१०.** २०, १०; १७६, २.

वृक्षतः **१.** १६, २; **८.** २, २७; ४, १४; ६, ४५; १४, १२; ३४, ९.

वृक्षति **१.** १, २; १४, ९; १२९, ८[२].

वृक्षथः **७.** ३३, ८; **१०.** ११५, १.

वृक्षथाय **१०.** ९९, १२.

वृक्षथेन **४.** ५, १.

वक्षन् **८.** ७४, १४.

वृक्षन् **१.** १०४, २.

वृक्षयं **१०.** ४९, ८.

वक्षांसि **१.** १२३, १०.

वक्षि **३.** १, १.

वृक्षि **१.** १८८, ३; **२.** ३, ११; ३६, ४; **३.** ४, १; ७, ९; १४, २; १५, ५; **५.** १, ११; ४, ४; ९, १; २६, १; ४३, १०; **६.** १५, १८; २१, १२; ४७, ९; **७.** १, १८; ७८, १; ९८, २; **८.** ५४, ६; **१०.** ३, ७; ७०, ३; १०; ७३, ४.

वृक्ष्यः **५.** १९, ५.

वृक्ष्यंतीऽइव **६.** ७५, ३.

वृक्ष्यामि **६.** ९, ६.

वृग्नुः **७.** १०३, २; **९.** ९७, १३.

वृग्नुना **१.** ८४, ३; **१०.** ३२, ३.

वृग्नुं **९.** १४, ६; ३०, २.

वृग्नून् **१०.** ३, ४.

वृग्वनान् **१०.** ३२, २.

वृग्वनुं **९.** ३, ५.

वृंकुः **५.** ४५, ६.

वृंकुऽतरा **१.** ५१, ११.

वृंकुं **१.** ११४, ४.

वंकू इति १. ५१, ११; ८. १, ११.

वंक्रीः १. १६२, १८.

वंगृदस्य १. ५३, ८.

वचः १. २६, २; १०; ३०, ४; ५४, ३; ५७, ४; ७५, १; ७८, ५; ८३, ३; ८४, १९; ९१, १०; ९३, २; ९४, ८; १०१, १; ११४, ६; १४४, ७; १४५, २; २. ३१, ५; ३. १०, ५; ३३, ८; ४. ३३, ५; ५. १, १२; ११, ५; २२, ४; ३९, ५; ५४, १५; ६. ४८, ११; ७. ८, ६; ९६, १; १०१, ५; ८. ८, ११; १९, १२; २४, २०; २५, २०; ३९, २; ४३, २७; ४६, १४; ६१, १; ९; ६६, ५; ७४, १; १०१, ५; ९. १०१, १३; १०३, १; १०. १७, १४; ३७, ६; ५०, ६; ६४, १०; ९७, १४; १०८, ८; १२२, २.

वचःऽभिः १. ३६, १; १८७, ११; ४. ४, ११; १६, ६; ५. १२, ५; ४५, ४; ६. ५, ६; ३९, २; ४४, ८; ७. १०४, ८; १०. ६१, २६; ११४, ५; १२०, ५.

वचःऽयुजा १. ७, २; २०, २; ८. २०, ९; ८. ४५, ३९; ९८, ९.

वचःऽवित् ९. ९१, ३.

वचःऽविदः १. ९१, ११; ९. ६४, २३.

वचःऽविदं ८. १०१, १६.

वचनस्यं ६. ३९, १; ४९, १२.

वचनाऽवंतः ९. ६८, १.

वचनेभिः १०. ११३, ९.

वर्चसः १. १४७, २; २. ९, ४; १६, ७; ३२, १; ४. ४, ११; ५, ८; ५. १२, ४; ६. ५१, ६; ७. ३७, ६; ८. ८६, १.

वचसं १. ११२, २.

वर्चसा १. ७६, ४; २. १८, ३; ३२, ३; ३. १४, ६; ४. १, १५; ५, १४; २५, २; ५. २९, ६; ६. ६२, ५; १०. १५१, १.

वर्चसी इति ७. १०४, १२.

वर्चसे ३. ३३, ५; ६. ६२, ९; ९. ९०, ६.

वचस्यते १. ५५, ४; ९. ९९, ६.

वचस्यया ४. ३६, ६; १०. ११३, ८.

वचस्यवे १. ५१, १३; १८२, ३; १०. ४०, १३.

वचस्या २. १०, ६; ६. २१, १; ४९, ८.

वचस्यां २. ३५, १.

वचस्युऽभिः ५. १४, ६.

वचस्युवं २. १६, ७.

वचांसि १. १४५, ३; ३. ३३, १०; ४. ३, १६; ३८, १०; ६. ३२, १; ५२, १४; ७. २३, १; ८. १०१, ७; १०. ६५, १३; ६६, ११; ९५, १; १०८, ६.

वच्यते १. १४२, ४.

वच्यंता ३. ६, २.

वच्यंते १. ४६, ३; १८४, ३.

वच्यमाना ३. ३९, १.

वच्यमानाः ३. ६, १; १०. ४७, ७.

वच्यस्व ९. २, २; ९७, २; १०८, १०.

वज्र १०. ८३, १; ८४, ६.

वज्रः १. ५१, ७; ५२, १०; ५७, २; ८०, ३; १२; १००, १३; २. ११, १०; १६, ६; ३. ३०, ६; ६. ४१, २; ४७, २८; ८. १२, ७; ७०, २; ९३, ९; ९६, ३; १००, ९; ९. ४७, ३; ७२, ७; ७७, १; १११, ३; १०. २७, २१; ४४, २; ९६, ३; ४; १४४, २.

वज्रऽदक्षिणं १. १०१, १; १०. २३, १.

वज्रऽबाहुः १. ३२, १५; १६५, ८; १७४, ५; २. १२, १२; १३; ३. ३३, ६; ४. २०, १; २९, ४; ७. १८, १२; १०. ६१, २२.

वज्रऽबाहुं ४. ३९, ४; ७. २३, ६; ९. ९७, ४९; १०. ४४, ३; १०३, ६.

वज्रबाहू इति वज्रऽबाहू १. १०९, ७.

वज्रबाहो इति वज्रऽबाहो २. ३३, ३.

वज्रऽभृत् १. १००, १२; ६. १७, २.

वज्रं १. ८, ३; ३२, २; ३; ७; ३३, १०; ५२, ७; ८; ५५, १; ५; ६१, ६; १२; ६३, २; ८१, ४; ८४, ११; ८५, ९; १२१, ३; १२; १३०, ४; १३१, ३; २. ११, ४; ६; १६, २; ३; २०, ८; ३. ३२, १२; ४४, ४; ५; ४. १६, ७; १७, ३; २०, ६; २२, ३; ४१, ४; ५. २९, २; ३१, ४; ४८, ३; ६. १७, १०; १८, ९; २०, ९; २२, ९; २३, १; ४; ४५, १८; ४७, २७; ७. १८, १८; २०, ४; २८, २; ८. ६, १४; ७, २२; १५, ७; २९, ४; ६१, १८; ६८, ३; ७६, ९; ९६, ५; ९; १००, ७; ९. १०६, ३; १०. २३, ३; ४८, ३; ६; ४९, २; ५२, ५; ७४, ५; ९२, ७; ९९, १; १०२, ३; १०५, ७; ११३, ५; १५३, ४.

वज्रऽवाहः ६. ४४, १९.

वज्रस्य ५. ३२, ७; ६. २०, ५; २७, ४; १०. २२, ३.

वज्रऽहस्त ८. २४, २४.

वज्रऽहस्त ३. ३२, ३; ५. ३३, ३; ६. १७, १; ४६, २; ५; ७. १९, ५; ३२, ४; ८. ९०, ४.

वज्रऽहस्तः १. १७३, १०; २. १२, १३; १९, २; ६. २९, १; ७. २१, ४; ८. २, ३१.

वज्रऽहस्तं ६. २२, ५; ७. ३२, ३.

वज्रऽहस्ता १. १०९, ८.

वज्रऽहस्तैः ८. ७, ३२.

वज्रात् २. ११, ९; ६. १७, ९; १०. १३८, ५.

वज्राय ८. १००, १२.

वज्रासः १. ८०, ८.

वज्रिणः १. ७, ७; ४०, ८; ३. ४६, १.

वज्रिणं १. ७, ५; ८. ६, १५; १२, २४; ६६, ७; ९. ८६, २; १०. ९६, ६.

वज्रिणा ६. ५९, ३.

वज्रिणे १. ८, ५; ३. ५३, १३; ६. ३२, १; ७. ३२, ८; ९७, ९; ८. ७, १०; २४, १; ६९, ६; १००, ८; ९. ३०, ६; ५१, २; ६३, १५.

वज्रिन् ५. ४०, ३; ८. २, १७; ४५, ८; ७०, ६.

वज्रिन् १. ३०, ११; १२; ५७, ६; ६३, ४; ५; ७; ८०, १; २; ७; ११; ८२, ६; १०३, ३; १३१, ६; ४. १९, १; २०, ३; ५. २९, १४; ३२, २; ३६, ५; ६. १९, १२; २०, ७; २२, १०; ४१, १; ४७, १४; ८. १२, २६; २१, ८; ४९, ३; ६; ७०, ५; ९२, १३; ९६, १७; ९७, १४; १५; ९९, १; १०. ८३, ६; १७९, ३.

वज्रिऽवः १. १२१, १४; ६. ३७, ४; ४५, १८; ८. १, ५; ६, ३३; ३७, १; ६६, ६; ११; ६८, ९; ९२, ११; १०. २२, ४; १०–१३.

वज्री १. ७, २; ११, ४; ३२, १; ५२, ५; १०३, ४; १३०, ३; ४. २०, २; ५. ३०, १; ३२, ४; ४०, ४; ६. १८, ६; २९, ३; ७. ३४, ४; ४९, १; ८. १, ८; ६, ४०; ३३, ४; ६६, ४; ९७, १३; १०. २२, २; ५५, ७.

वज्रेण १. ३२, ५; ३३, १२; १३; ५७, ६; ६१, १०; ११; ८०, ५; ६; १३; १०३, २; ७; १२१, ११; १३०, ७; १३१, ७; १३२, ६; २. १५, ३; ६; १७, ६; ३. ३३, ७; ४. १७, ३; ७; १९, ३; २२, ५; ५. २९, ६; ३२, ४; ६. २१, ७; ६८, ३; ८. ६, ६; ७६, २; ८९, ३; ९६, १७; १०. २८, ७; १११, ६.

वटूरिणा १. १३३, २.

वणिक् ५. ४५, ६.

वणिजे १. ११२, ११.

वतंतः ७. ६०, ६.

वतेम ७. ३, १०.

वत्सः १. ९५, ४; १६४, ९; ३. ५५, ६; ८. ८, ८; ११; १५; १९; ९, ६; ११, ७; ७२, ५; ९. ६९, १; १०. ८, २; २८, ९.

वत्सःऽइव ९. १०५, २.

वत्सऽप्रचेतसा ८. ८, ७.

वत्सं १. ३८, ८; ७२, २; ९५, १; १४६, ३; १६४, १७; २७; २८; २. २, २; १६, ८; ३. ४१, ५; ५५, ४; १३; ४. १८, १०; ६. ४५, २५; २८; ७. ८६, ५; १०१, १; ८. ६९, ११; ७०, १५; ८८, १; ९५, १; ९. १२, २; १३, ७; ६१, १४; ८६, २; १००, १; ७; १०४, २; १०. ५३, ११; १४५, ६; १४९, ४.

वत्संऽइव ३. ३३, ३.

वत्सस्य ८. ६, १; ९, १; ९. १९, ४; १०. १२३, ३.

वत्सात् २. २८, ६.

वत्सान् ८. ७०, १४.

वत्सानां ६. २४, ४.

वत्साय १. १११, १; ८. ९, १५.

वत्सासः ७. ५६, १६; ८. ७२, १४.

वत्सिनीनां ७. १०३, २.

वत्से १. १६४, ५.

वत्सेन १. ११०, ८.

वत्सैः ५. ३०, १०.

वद १. २८, ५; ३८, १३; २. ४२, २; ४३, २[२]; ३; ५. ८३, १; ७. १०१, १; ८. ५१, ३; १०. १४१, १.

वदत् १. ११९, ९; ८. ४५, ५.

वदत १. ६४, ९; १०. ९४, १; १६६, ५.

वदतः ६. ५९, ४.

वदति १. ८३, ६; १३५, ७; ७. १०३, ५; १०. ७१, ११; १६५, ४.

वदति १. ४०, ५; २. १३, ३; ४३, १; ५. ६३, ६; १०. ६२, ४.

वदते ८. ७३, ८; १०. १४६, २.

वदत्ऽभिः ६. १८, ५.

वदत्ऽभ्यः १०. ९४, १.

वदथन ७. १०३, ५.

वदध्वं १०. १९१, २.

वदन् ५. ३१, १२; ८. ३४, २; ९. ११३, ४[३]; ६; १०. २८, १२; ३६, ४; ४८, ६; ११७, ७.

वदंतः १. १६१, ९; २. ४३, १; ७. १०३, ६; ७; १०. १०, ४; ६१, १०.

वदतं ७. १०३, ३; १०४, १३.

वदता २. ३९, ६.

वदंति ५. ३७, २; १०. ७३, १०.

वदंति १. १६४, ४५; ४६; ४. ५, ८; १४; ८. १००, ११; ९. ७२, २; ९७, ८; १०. ९४, २–४; १३.

वदंती ८. १००, १०.

वदंतु १०. ९४, १.

वदंते १०. ९७, २२.

वदसि २. ४३, ३.

वदस्व १. १७०, ५.

वदाति ६. ९, २; ३; ७. ३३, १४.

वदाथः १०. ८५, २७.

वदान् १. ३७, ३; १०. १६६, ३.

वदाम १०. ९४, १.

वदामः १०. ८८, १४.

वदामसि ८. २१, ६.

वदामसि १. ८७, ५.

वदामि १. १०५, ७; ६. ४७, १०.

वदामि १०. ३४, १२; ८८, १८; १२५, ४; ५.

वदासि १०. ८५, २६; ९५, ११.

वदे ७. ८६, २.

वदेत १०. ३१, २.

वदैते इति १०. ८८, १७.

वदेम १. ११७, २५; २. १, १६; २, १३; १०, ६; ११, २१; १२, १५; १३, १३; १४, १२; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; २३, १९; २४, १६; २७, १७; २८, ११; २९, ७; ३३, १५; ३५, १५; ३९, ८; ४०, ६; ४२, ३; ४३, ३; ३. ५५, ३; ८. ४८, १४.

वद्मा ६. ४, ४; १३, ६.

वधः १. ३२, ९; १७४, ८; २. १९, ७; ४. २२, ९; ५. ३२, ३; ७; ७. २५, ३; ८. २४, २७; १०. २२, ८; ४९, ३.

वधः १. १०१, ४; २. २१, ४; २३, १२; ७. ५६, १७; ८. ६२, १२; १०. ११७, ६.

वधःऽयंती १. १६१, ९.

वधत्रे इति ९. ९७, ५४.

वर्धत्रैः ४. २८, ४; ८. ९६, १७.
वधर्नाभिः ७. ८३, ४.
वधं १. ५, १०; ५५, ५; १७५, ४; २. ३०, ३; ५. ३४, २; ७. १०४, ४; २०; २५; १०. ८९, ९; १०२, ३; ११७, १; १३३, ३; १५२, ५[२].
वधरिर्ति २. ३४, ९.
वधऽस्नैः १. १६५, ६; ५. ४१, १३; ७. ६, ५; ९. ९७, १५.
वधस्नो इति वधऽस्नो ९. ५२, ३.
वधात् १०. २५, ३.
वधानां १. ३२, ६.
वधार्य १. २५, २; ६. १६, ३१.
वधिपः ६. १७, १.
वधिष्ट ८. १०१, १५.
वधिष्टन ५. ५५, ९.
वधिष्टं ४. ४१, ४.
वधीः १. ३३, ४; ४. ३०, ८; ६. ३३, ३; ८. ४५, ३४.
वधीः १. ५३, ८; १०४, ८; ११४, ७; ८; १७०, २; ७. ४६, ४; ८. ७९, ८.
वधीत् ४. १७, ३; ६. २७, ५; ८. ३२, २.
वधीत् १. ३८, ६; २. ४२, २; ५. ४४, १२; ८. ६७, २०; ७५, ९.
वधीं १. १६५, ८; १०. २८, ७.
वधूः ५. ३७, ३; १०. २७, १२; ८५, ३३.
वधूःऽईव ८. २६, १३.
वधूनां ८. १९, ३६.
वधूऽमतः ८. ६८, १७.
वधूऽमतः १. १२६, ३; ६. २७, ८.
वधूऽमता ७. १८, २२.
वधूऽयुः ९. ६९, ३; १०. ८५, ९.
वधूयुःऽईव ३. ५२, ३; ६२, ८; ४. ३२, १६.
वधूऽयोः १०. २७, १२.
वधेन १. ३२, ५; ५२, १५; ३. ३२, ६; ४. १८, ७; ९; ५. ४, ६; २९, १०; ३२, ८; ७. १०४, १६; ९. ९१, ४.
वधैः १. ९४, ९; १२१, ९; १२९, ६; १३३, ६; २. २८, ७; ६. २०, ४; ८. १, २८; ५१, ८; ९. ५२, ३.
वध्र्यः १. ३३, ६; ८. ४६, ३०[२].
वध्रिऽअश्वः १०. ६९, ४; १०.
वध्रिऽअश्वस्य १०. ६९, १; २; ११; १२.
वध्रिऽअश्वार्य ६. ६१, १.
वध्रिः १. ३२, ७.
वध्रिणा १०. १०२, १२.
वध्रिऽमत्याः १. ११६, १३; ११७, २४; ६. ६२, ७; १०. ३९, ७; ६५, १२.
वध्रिऽवाचः ७. १८, ९.
वध्रीन् २. २५, ३.
वध्र्वः ५. ४७, ६; ७४, ५; १०. ८५, ३०; ३१.
वध्वं १०. १०७, ९.
वध्वा ७. ६९, ३.
वनः ८. ४५, २३.
वनऽऋक्षं ९. १०८, ७.
वनत ८. ७, ९.
वनतं १. ३, २; ७. ९४, २.
वनतं १. ९३, ९.
वनतां १. १६२, २२.
वनते ५. ४१, १७; ६५, १; ६. १५, ६[२].
वनते ३. १९, १; ५. ३, १०; ४, ३; ४१, १७; ६५, ४; ६. १६, २८; २०, ९; २५, ४; ३८, १; ८. ७२, १; १०. ५३, ११.
वनथः १. ४६, १४; ४. ४४, २; ७. २, ७.
वनदः २. ४, ५.
वनऽधितिः १. १२१, ७.
वननाः ९. ८६, ४०.
वनंति ६. ६, ३.
वनंनूऽवतः ८. १, ३१.
वनंनूऽवति ८. १०२, १९; १०. ९२, १५.
वनन्नूऽवति ७. ८१, ३.
वनंनूऽवती ८. ६, ३४.
वनें ५. ७८, ८; ६. १८, १०; ७. १०४, २१; ८. ७२, ४; ९. ६४, २; १०. २३, ४; ३१, ७.
वनंऽकरणात् १०. १६३, ५.
वनर्गुः १. १४५, ५.
वनर्गूऽइति १०. ४, ६.
वनवंत् ६. ३३, १.
वनवत् २. २५, १; २; २६, १[२]; ५. ३, ५; ३७, २; ४४, ७; ९. ७७, ४; १०. २७, १८.
वनवसे ६. १६, १८.
वनऽसदः २. ३१, १; १०. ४६, ७.
वनऽसदं १०. १३२, ७.
वनसा १०. १७२, १.
वनसे १. १४०, ११.
वनस्पतिः १. ९०, ८; ९१, ६; १६६, ५; २. ३, १०; ३. ५३, २०; ८. २०, ५; ५४, ४; ९. १२, ७; १०. ११०, १०.
वनस्पतिऽभिः ७. ३४, २३.
वनस्पतिऽभ्यः ६. ४७, २७.
वनस्पतिं ६. ४८, १७; ९. ५, १०; १०. १०१, ११.
वनस्पती इति १. २८, ८.
वनस्पतीन् १. ३९, ५; १५७, ५; ३. ३४, १०; ५. ७, ४; ४१, ८; ४२, १६; ८४, ३; ८. २७, २; १०. ६०, ९; ६४, ८; ६५, ११.
वनस्पतीनां ८. २३, २५.
वनस्पते ३. ४, १०; ८, १; ६; ११; ६. ४७, २६; १०. ७०, १०.
वनस्पते १. १३, ११; २८, ६; १४२, ११; १८८, १०; २. ३७, ३; ३. ८, ३; ५. ५, १०; ७८, ५.
वनस्पतौ ६. १५, २; ८. ९, ५.
वनस्य १. २४, ७; ८. ३४, १८; ९. ९५, १.
वना १. ५४, १; ५; ६४, ७; ६५, ४; ६६, १; ८८, ३; १४३, ५; २. ४, ६; ३. १, १३; ५५, ४; ५. ९, ४; ४१, १०; ११; ५७, ३; ६०, २; ६. २, ९; ६, ३; ४८, ५; ६०, १०; ७. ४, २; ८. ३५, ७; ९. ९०, २; १०. २८, ८; ११५, २.
वना ३. ९, २.

वनाऽइव १. १२७, ३; ४; ६. ३३, ३; ८. १२, ९; ४०, १; १०. ८९, ७.
वनात् १. २९, ६.
वनाति ७. १५, ४.
वनानां १. ७०, २; ९. ९६, ६.
वनानि १. ६५, ४; १०३, ५; १७१, ३; २. ३८, ७; ३. ५१, ५; ५. ५८, ६; ६. ६, ५; ३१, २; ३९, ५; ७. ७, २; ८. १, १३; ४३, ३; ९. ३३, १; १०. ६८, १०; ७९, २; ८९, ५; १३; ९१, ५.
वनां १०. ४६, ५.
वनामहे ५. ७, ३.
वनामहे १. १५, ८; ८. ९५, ६; ९. ६१, ११.
वनामहै ९. १०१, ९.
वनाव १०. ९८, ३.
वनिता ३. १३, ३.
वनिनः १. ३९, ३; ५८, ४; ९४, १०; १३०, ४; १३९, १०; १४०, २; १८०, ३; ३. ४०, ७; ६. १३, १; ७. ४, ५; ३४, २५; ३५, ५; ४३, १; ८. ३, ५; १०. ७३, ८; ९१, ६; १३८, २.
वनिनं १. ६४, १२; ११९, १; ६. ८, ५.
वनिनानि १०. ६६, ९.
वनिषीष्ट १. १२७, ७[२].
वनिष्ठः ७. १०, २; १८, १.
वनिष्ठोः १०. १६३, ३.
वनीयान् ५. ७७, २; १०. ११७, ७.
वनीवानः १०. ४७, ७.
वनुते १०. २७, १२; १०७, ७.
वनुथः २. ३०, ६; १०. ६१, ३.
वनुं १०. ७४, १.
वनुयाम १. १३२, १; ८. ४०, ७.
वनुयाम १. ७३, ९; ५. ३, ६; १०. ३८, ३.
वनुषः १. १५०, ३; ३. २७, ११; ४. २२, ९; ६. ६, ६; २५, ३; ७. २५, ३; ३८, ५; ८. २५, १५; ९. ६४, २९; १०. ९६, १.
वनुषंत १०. १२८, ३.
वनुषा ९. ९१, ५.
वनुषां ४. ५०, ११; ६. ६८, ६; ७. २१, ९; ८३, ५.
वनुषे ४. ४४, ३.
वनुष्यतः १. १३२, १; २. २५, १; २; २६, १; ६. १५, १२; ७. १, १५; ५६, १९; ८. ४०, ७; ९. ७७, ४.
वनुष्यता ९. ६३, ११.
वनुष्यतां ६. ६२, १०.
वनुष्यति ७. ८२, १.
वनुष्यते ९. ७, ६.
वनुष्यन् ६. ६, ६.
वनुष्यात् ६. ५, ४.
वनुष्व १. १६९, १.
वनून् ४. ३०, ५.
वने १. ५५, ४; ५८, ५; १४८, ४; २. १४, ९[२]; ४. ७, ६; ७. १, १९; ९. ६, ५; ७, ३; ४५, ५; ६६, ९; ७४, १; ७८, २; ८८, २; ५; ८९, १; १०६, ११; १०७, २२; १०. ४, ५; २३, २; २९, १; ३१, ९; १०१, ११.
वनेऽजाः ६. ३, ३; १०. ७९, ७.
वनेभ्यः २. १, १.
वनेम १. ७०, १; १२९, ७[२]; २. ५, ७; ८. १९, २०.
वनेम २. ११, १२; ७. ४७, १; ८. ९२, ३१; १०. १०५, ८.
वनेमहि ७. ९४, ९.
वनेऽराट् ६. १२, ३.
वनेरिति वनेः २. ६, १.
वनेऽवने ५. ११, ६; १०. ९१, २.
वनेषाट् १०. ६१, २०.
वनेषु १. ६७, १; ७०, ५; १२८, ३; ३. ६, ७; २३, १; २९, ६; ३४, ३; ४. ७, १; ५. १, ५; ८५, २; ८. ४३, ८; ६०, १५; ९. ७, ६; २७, ३; ६२, ८; ८६, ३१; ९२, ६; ९६, २३; १०७, १०; १८.
वनोति १. १३३, ७; १०. १०५, ५.
वनोति ४. २३, १०.
वनोषि १. ३१, १३; १४.
वंत १. १३९, १०.
वंतारः ३. ३०, १८; ७. ८, ३.
वंदते १. १७३, १२; ४. ५०, ७; ७. ७३, २.
वंदते १०. ११५, ८.
वंदध्यै १. २७, १; ६१, ५; ३. ४, ३.
वंदनः १. ११९, ६.
वंदनं १. ११२, ५; ११८, ६; ११९, ७; ७. ५०, २; १०. ३९, ८.
वंदनऽश्रुत् १. ५५, ७.
वंदना ७. २१, ५.
वंदनानि ३. ४३, ४.
वंदनाय १. ११६, ११; ११७, ५.
वंदनेऽस्थाः १. १७३, ९.
वंदमानः १. २४, ११; ३. १८, ३; ५. ३, १०; ७. ६, १; ८. २२, १३; १०. १४९, ५.
वंदमानं २. ३३, १२.
वंदस्व १. ३८, १५; ५. ५८, २; ८. २०, २०.
वंदस्व ८. २०, १४; ४२, २; १०. ३०, १०.
वंदामहे ४. ५७, ६.
वंदारु ४. ४३, १; ५. १, १२; ६. ४, २.
वंदारुः १. १४७, २.
वंदि १०. ६१, १६.
वंदिता १०. ३३, ७.
वंदितारं २. ३४, १५.
वंदितुः ९. ९३, ५.
वंदिषीमहि १. ८२, ३.
वंदे ५. २८, ४; ७. ६, १.
वंदे १. १४७, २; २. ३५, १२.
वंद्य १. ३१, १२; ७९, ७.
वंद्यः २. ७, ४; ४. ५४, १; ९. ७, २; १०. ४, १; ११०, ३.
वंद्या १०. ६३, २.
वंद्यासः १. ९०, ४; १६८, २.
वंद्येभिः ५. ४१, ७.
वंधुरः १. ३४, ९.
वंधुरे १०. ११९, ५.
वंधुरऽयुः ४. ४४, १.

वंधुराऽइव ३. १४, ३.

वंधुरे १. १३९, ४; ६. ४७, ९.

वंधुरेषु १. ६४, ९.

वंधुरेऽस्थाः ३. ४३, १.

वन्यै ९. ९७, ४५.

वन्वते २. २१, २.

वन्वन् १. १२१, ९; ६. १२, ४; १६, २०; २६; १८, १; ८. ३१, ३; ९. ८९, ७; ९६, ८; ११; १०. ६१, २.

वन्वन् ७. ४८, ३.

वन्वंतः २. ४, ९; ६. १६, २७; ९. ६१, २४.

वन्वंता ७. ८३, ४.

वन्वंतु ७. २१, ९.

वन्वंतु १०. ३२, २.

वन्वानः ३. ८, २; ५. २९, ९.

वन्वे १०. ९६, १.

वप ८. ९६, ९.

वपः ४. १६, १३.

वपत १०. १०१, ३.

वपंति ८. ६६, ४.

वपते १. ९२, ४; १६४, ४४.

वपंत ७. ५६, ३.

वपंतः १०. ९४, १३.

वपंता १. ११७, २१.

वपंति ६. ६, ४; ८. ७, ४; १०. ८५, ३७.

वपंतु २. ३३, ११.

वपसि १०. १४२, ४.

वपाऽउदरः ८. १७, ८.

वपाऽवंतं ५. ४३, ७; ६. १, ३.

वपुः १. १०२, २; १४१, २; १४४, ३; १८३, २; ४. २३, ६; ४४, २; ५. ४७, ५; ७३, ३; ६. ४४, ८; ४९, ५; ६६, १; ७. ६६, १४; ८८, २; ८. १९, ११; ६९, १३.

वपुःऽतरः ९. ७७, १.

वपुःऽतरं १०. ३२, ३.

वपुःऽतरा २. ३, ७.

वपुःऽभिः १. ६२, ८.

वपुषः १. ११८, ५; ९. ७७, १; १०. ३२, ३; १४०, ४.

वपुषां ४. ७, ९; ५. ६२, १.

वपुषाय ३. २, १५.

वपुषि ८. ४६, २८.

वपुषीऽइव १०. ७५, ७.

वपुषे १. ६४, ४; ११९, ५; १४१, १; १४८, १; ४. २३, ९; ५. ३३, ९; ७३, ३; ६. ६३, ६.

वपुष्यः ४. १, ८; १२; ५. १, ९.

वपुष्यतः ८. ६२, ९.

वपुष्यन् ३. १, ४.

वपुष्या १. १८३, २.

वपुष्येऽइति १. १६०, २.

वपूंषि ३. १, ८; १८, ५; ३९, ३; ५५, ९; ११; १४; ५७, ३; ४. २३, ९.

वर्साऽइव १०. १४२, ४.

वप्संसः १. १८१, ८.

वं १०. २८, ७.

वर्मन् १०. १०८, ८.

वम्रः १. ५१, ९; ८. १०२, २१.

वम्रकः १०. ९९, १२.

वम्रं १. ११२, १५.

वम्रस्य १०. ९९, ५.

वम्रीभिः ४. १९, ९.

वय १०. १३०, १^{२}.

वयः १. २४, ६; २५, ४; ३७, ९; ४८, ६; ४९, ३; ६६, २; ७१, ६; ७; ८३, ४; ८५, ७; ८८, १; १०३, ७; १०४; १, ७; १११, १; २; ११८, ५; १२४, १२; १२५, २; १२७, ८^{२}; १३६, २^{२}; १४०, ९; १४१, ८; १५१, ९; १५५, ५; १६६, १०; १७८, २; २. १, १२; ४, ९; १३, ११; १९, २; २०, १; २३, १०; २८, ४; ३१, १; ५; ४३, १; ३. १८, ४; २९, ८; ५१, ६; ४. १७, १८; ३६, ८; ४३, ६; ५. ४, ६; ८, ५; १५, ३; १६, १; ४१, १३; ४३, १५; ५५, १; ५९, ७; ७३, ५; ७५, ६; ६. १३, ५; २२, ४; २८, ६; ४०, १; ४; ४४, ९; ४५, २; ४६, १४; ६३, ६; ७; ७. ३६, ५; ९; ४५, ४; ५८, ३; ६९, ४; ९७, १; १०४, १८; ८. ३, २३; ५, ३३; ७, ३५; २०, १३; २१, ५; ३३, ७; ३९, ४; ४७, २; ३; ६२, १; ७४, १४; ८७, २; १०२, १; ९. १९, ७; ६८, १०; ९०, ६; ९४, ४; १११, २^{२}; १०. २७, २२; ३०, १२; ३९, ८; ४३, ३; ४; ४६, १०; ६८, १; १२; ७३, ११; ७७, ७; ८०, ५; ९५, ४; ९६, १०; १००, ३; १०४, ४; १२७, ४; १४०, १; १४४, ५; १५६, ५.

वयःऽइव १. ८७, २.

वयःऽकृत् १. ३१, १०; १०. ७, ७.

वयःऽकृतः ९. २१, २; ६९, ८.

वयःऽजुवः ९. ६५, २६.

वयःऽधः ९. ८१, ३.

वयःऽधाः १. ७३, १; २. ३, ९; ३. ३१, १८; ४९, ३; ४. ३, १०; १७, १७; ५. ४३, १३; ६. ७५, ९; ८. ४८, १५; ७२, ४; ९. ९६, १२; ११०, ११; १०. ७, ७.

वयःऽधां ६. ६, ७; ४९, ९; ९. ९०, २.

वयःऽधेयाय १०. २५, ८.

वयःऽधै १०. ५५, १; ६७, ११.

वयःऽभिः १०. ४५, ८.

वयःऽवयः ५. १५, ४; ८. ५५, ४.

वयःऽवृधः ५. ५४, २.

वयःऽवृधं ८. ६०, ११.

वयःऽवृधा ५. ५, ६.

वयत् १०. २८, ९.

वयत १०. ५३, ६.

वयतः २. २८, ५.

वयति ८. २१, १०.

वयंतः ७. ३३, ९.

वयंति ६. ९, २.

वयंति ५. ४७, ६; ९. ९९, १; १०. १३०, १.

वयंती २. ३८, ४.

वयं १. १, ७; ७, ५; ८, ३; ४^{२}; १७, ६; २३, ४; २४, २; ५; १५; २६, ७; ३०, १०; २१; ३१, १०; ३७, १५; ५०, १०; ५७, ४; ६०, ५;

६६, ५; ७३, ८; ८२, ३; ८६, ६; ८९, २; ३; ५; ९१, ११; ९३, ४; ९४, १–१४; ९७, ४; १०१, ११; १०२, ४; १०५, १९; ११४, ४; ९; १३०, १; १३२, १; १३६, ७[२]; १४१, १०; १३; १५७, २; १५९, ५; १६४, ४०; १६५, ५; १६७, १०[३]; १७८, ५; १८०, ७; १०; १८७, २; ११; १८९, ८; १९१, १०–१२; २. २, १०; ५, ७; ८; ७, ३; ८, ६; १२, १५; १७, ८; २०, १; २३, ९; १०; २७, १४; ३. १, २१; ३, ९; ८, ११; १४, ५; २१, ५; २६, ५; २७, ३; १५; २९, ४; ३३, ४; ६; ३५, ५; ४०, १; ४१, ७; ५९, ३; ६२, ११; ४. २, १४; ३, २; ४, १४; १७, १८; २०, ३; १०; २९, ५; ३२, ४[२]; १३; १८; ३६, ९; ४२, १०; ४९, ५; ५०, ६; ५१, ११; ५७, १; ५८, २; ५. ३, ६[२]; ४, ७[२]; ८; ८, ४; १६, ५; ३०, ३; ३३, ५; ३५, ८; ३९, २; ४८, १; ५; ५६, ८; ६५, ५; ६६, ६; ७०, २; ७२, १; ७४, ३; ८२, १; ६. १, ६; ८, ६; १५, १९; १६, ३८; १९, १३; २३, ५; २६, ८; ४४, १०; ४५, ५; ४६, ३; ४८, १; ५३, १; ५४, ८; ९; ५७, १; ५; ५९, ३; ७१, २; ७५, ८; ७. १, २४; ४, ६; १४, १; २[४]; १५, ८; २०, ८; २५, ५; ३०, ४; ३२, २७; ३७, ४; ४१, २; ४; ५; ४३, ५; ४७, १; ५५, ७; ६०, १; ६५, २; ७८, ५; ८१, ४; ८२, १; ८६, ५; ८७, ७; ८. ३, २; ६, ३३; १२, २३; १४, ६; १७, ३; १९, १६; ३५; २१, १; ४; ६; ७; ११; २२, ११; २४, ८; २५, १२; २६, ९; २२; २७, ७; २०; ३२, ७; ३३, १; ४०, ६; ७; ४३, १२; २३; ४४, २७; ४५, १७; ४६, १; २५; ४७, १८; ४८, ९; १४; ५१, ५; ६; ५३, ७; ५४, ८; ६१, १४; ६२, १२; ६४, ६[२]; ६५, ६; ६६, ५; ७; ११; ६७, १६; ७५, १६; ८३, १; ६; ९२, १२; २७; ३२; ९. ८, ९; ३१, ६; ४५, ३; ६१, ४; २३; २९; ६५, ९; ६६, १४; ७९, २; ८६, ३८; ९७, ४३; ५८; ९८, १२; १०. २, २; ४; ४, ४; १२, ८; १४, ६; १८, ९; २६, ४; २७, ९; ३१, १; ३६, ९; ३७, ८; ३८, २; ३; ३९, १; ४१, १; ४२, ६; १०; ५३, ८; ५७, १; ६; ७२, १; ८४, ४; ८७, २२; ८९, १७; ९४, १; १०१, ५; १२०, ५; १२६, २; १२७, ४; १२८, १; १३६, ३; १६०, ५; १६९, ४.

वयंऽवयं १०. २२, १२.

वयंसः ८. ४८, १.

वयंसा २. १०, ४; ३३, ६; ६. ३६, ५; ८. ४, ९; ९. ९७, ४७; १०. १०६, ५.

वयंस्वतः २. २४, १५; ५. ५४, १३.

वयांसि ३. ३, ७; ९. ९, १; १०. ४६, १; १२०, ५.

वयाः १. ५९, १; २. ३५, ८; ६. १३, १; २४, ३; ७. ४०, ५; १०. ९२, ३.

वयाःऽईव २. ५, ४; ६. ७, ६; ८. १३, ६; १७; १९, ३३.

वयाकिनं ५. ४४, ५.

वयां १. १६५, १५; १६६, १५; १६७, ११; १६८, १०; ५. १, १; १०. १३४, ६.

वयांऽईव ६. ५७, ५.

वयायाः १०. १२४, ३.

वयाऽवंतं ६. २, ५.

वयियोः ८. १९, ३७.

वयिष्यन् ७. ३३, १२.

वयुनं १. १८२, १; ३. ३, ४; ५. ४८, २.

वयुनंऽवत् ४. ५१, १; ६. २१, ३.

वयुनऽवित् ५. ८१, १.

वयुनऽशाः ६. ५२, १२.

वयुनां १. ९२, ६; १४४, ५; १४५, ५; १६२, १८; २. २४, ५; ४. ५, १३; १६, ३; ७. ७५, ४; १०. ४९, ५.

वयुनांनि १. ७२, ७; ९२, २; १५२, ६; १८९, १; २. १९, ३; ८; ३. ५, ६; ६. १५, १०; ७५, १४; ७. १००, ५; १०. ४४, ७; ४६, ८; ११४, ३; १२२, २.

वयुनें ३. २९, ३.

वयुनेंषु २. ३४, ४; ६. ७, ५; ८. ६६, ८.

वय्यं १. ५४, ६; ११२, ६; ९. ६८, ८.

वय्याऽइव २. ३, ६.

वय्याय २. १३, १२; ४. १९, ६.

वरः ९. १०१, १४.

वरःऽभिः १०. ८९, १.

वरत् ४. २, ९; ६. ४५, २४.

वरंते ६. २२, ११.

वरते ४. ४२, ६.

वरत्र्यां १०. ६०, ८.

वरत्राः ४. ५७, ४; १०. १०१, ५.

वरत्रायां १०. १०२, ८.

वरथः ५. ३१, ९.

वरंत ४. ६, ६.

वरंत १. १२१, १५; १४०, १३; २. २४, ५; ३. ३२, ९; १६; ५. ५५, ७.

वरंते ४. ३१, ९; ८. ६६, २; ८८, ३.

वरंते ४. ३२, ८; ५. २, १०; ७३, ५; ८. २४, ५; १०. १७८, ३.

वरं १. ४, ४; ८८, २; ११९, ३; १४०, १३; २. ५, ५; ११, २१; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; ३९, २; ६. ६४, ५; ७. १, ४; ६, ६; ५४, ३; ६५, ४; ७०, ५; ९. ४५, २; ६८, २; ९७, २२; १०. २५, ११; ११५, ६; ११६, २; १३३, ७; १६४, २.

वरऽशिखस्य ६. २७, ४; ५.

वरऽसत् ४. ४०, ५.

वरंस्य ८. ६३, ५.

वरस्या ५. ७३, २.

वरस्यां ६. ४९, ११.

वरा ५. ४४, १२.

वरा १०. ८५, ८; ९.

वरांसि १. १९०, २; ४. २१, ८; ६. ६२, १; २; १०. ८९, २.

वराःऽइव १. ८३, २; ५. ६०, ४.

वराते १. ६५, ३; ५. ३२, ९.

वरान् १०. ३२, १.

वराय १. ७६, १; १४३, ५; ६. २१, ४; ४४, २१; ७. ५९, २; ८. ८२, ३; ८४, ४; १०. २९, ६; ५०, ६.

वराहः ९. ९७, ७.

वराहं १. ६१, ७; ११४, ५; ८. ७७, १०; १०. २८, ४; ९९, ६.

वराहऽयुः १०. ८६, ४.

वराहुं १. १२१, ११.

वराहून् १. ८८, ५.

वराहैः १०. ६७, ७.

वरिति वः २. १४, ३; ५. ३२, १.

वरिर्ति वः १. १२१, ४.

वरिमता १. १०८, २.

वरिमन् ३. ५९, ३; ४. ५४, ४; ६. ६३, ११; १०. २८, २; २९, ७.

वरिमा १. ५५, १.

वरिमाणं ६. ४७, ४; ८. ४२, १.

वरिवः १. ५९, ५; ६३, ७; १०२, ४; ३. ३४, ७; ४. २१, १०; २४, २; ६; ५०, ९; ५५, १; ५. २९, १०; ६. १८, १४; ४४, १८; ५०, ३; ७. २७, ५; ४७, ४; ४८, ४; ६२, ६; ९८, ३; ९. ६२, ३; ६४, १४; ६८, ९; ८४, १; ९७, १०; १०. ४२, ११; ५२, ५; ११६, ३.

वरिवःऽकृत् ८. १६, ६.

वरिवःऽधातमः ९. १, ३.

वरिवःऽधां १. ११९, १.

वरिवःऽवित् ९. ३७, ५; ६१, १२; ६२, ९; ९६, १२; ११०, ११; १०. ३८, ४.

वरिवःऽविदः ८. २७, १४; ९. २१, २.

वरिवःऽविदं २. ४१, ९.

वरिवःऽविदा १. १७५, ५.

वरिवस्य ८. ४६, १०.

वरिवस्य ९. ९६, ३.

वरिवस्यन् ६. २०, ११.

वरिवस्यंतः ७. ५६, १७.

वरिवस्यंतु १. १२२, ३; १४; ५. ४२, १२; ६. ५२, १५.

वरिवस्या १. १८१, ९.

वरिवस्यातः १०. ७६, १.

वरिवांसि ९. ९७, १६.

वरिवोवित्ऽतरस्य ८. ४८, १.

वरिवोवित्ऽतरा १. १०७, १.

वरिष्ठः ६. ३७, ४.

वरिष्ठं ५. ४८, ३; ८. २५, १३; ९७, १०.

वरिष्ठया ५. २५, ३.

वरिष्ठा ६. ४१, २.

वरिष्ठे ६. ४७, ९.

वरिष्ठे इति ४. ५६, १.

वरीमन् ६. ६३, ३.

वरीमऽभिः १. ५५, २; १३१, १[2]; १५९, २; ९. ७१, ४.

वरीयः १. १२४, ५; २. १२, २; ५. ४५, ५; ४९, ५; ६. ६९, ५; ७५, १८; १०. ७०, ५; ८; १००, ८; १०८, १०; ११; ११३, ५; १५२, ५.

वरीयसी १. १३६, २.

वरीयान् ३. ३६, ६.

वरीवर्ति १. १६४, ३१.

वरीवृजत् ७. २४, ४.

वरुण १. १५१, ६; २. २७, १४; २९, १; ५. ४६, २; ६७, १; २; ७१, १–३; ७. ५९, १; ६६, ३; ८. १९, ३५; ४७, १; ६९, ११.

वरुण १. २४, ११; १४; १५; २५, १; ३; १९; ५०, ६; १२२, ७; २. २७, ६; ८; १०; १७; २८, २; ३; ५–११; २९, ७; ४. १, १८; ४१, ११; ५५, १; ५. ६२, ५; ८; ६९, १; २; ७०, १; ८५, ७[2]; ८; ७. ६४, ५; ६६, ९; १७; १८; ८६, ३; ४; ६; ८; ८७, २; ८८, ५; ६; ८९, १; ५; ८. १८, २१; २७, ७; १५; ४२, ३; ६९, १२; ८३, ४; १०. ५१, ४; ६; ६४, १२; १२४, ५.

वरुणः १. १७, ५; २३, ६; २४, ७; ८; १२; १३; २५, १०; १३; २६, ४; ३६, ४; ४०, ५; ४१, १; ४३, ३; ४४, १४; ७९, ३; ९०, १; ९४, १६; ९५, ११; ९८, ३; १००, १९; १०१, ३; ११; १०२, ११; १०३, ८; १०५, १५; १९; १०६, ७; १०७, ३; १०८, १३; १०९, ८; ११०, ९; १११, ५; ११२, २५; ११३, २०; ११४, ११; ११५, ६; १३६, ३; ७; १४१, ९; १४३, ४; १५६, ४; १६१, १४; १६२, १; १६३, ४; १८६, २; ३; २. १, ४; २७, १; २; ३८, ८; ९; ३. ४, २; ६; ५, ४; १४, ४; ५४, १०; ४. १३, २; ४२, २; ३; ५५, ४; ५. ३, १; २६, ९; ४०, ७; ४६, ५; ४८, ५; ४९, ३; ६४, ५; ६५, १; ६७, ५; ६८, २; ७२, ३; ८५, २–४; ६. ३, १; २४, ५; ४९, १; ५१, १०; ६२, ९; ७५, १८; ७. १२, ३; २८, ४; ३४, १०; २४; २५; ३५, ६; ३८, ४; ३९, ७; ४०, २; ४; ४९, ३; ४; ५१, २; ५६, २५; ६०, ४–६; ८; ६२, ३; ६; ६४, १; ६६, ११; १२; ८२, १०; ८६, ३; ८७, १; ४–६; ८८, ३; ४; ७; ८. १५, ९; २५, २; १३; २६, ११; २७, ६; १७; ३१, १३; ६७, २; ९४, ५; ९. ६४, २४; ७३, ३; ७७, ५; ८१, ४; ९०, २; १०. ८, ५; ११, १; ३१, ९; ३६, १; ६५, १; ९; ६६, ५; ७५, २; ८३, २; ८४, ७; ९२, ४; ६; ९३, ४; ९८, १; ९९, १०; १०९, २; १२४, ४; ७; १२६, १; १४७, ५; १७३, ५.

वरुणऽधृतः ७. ६०, ९.

वरुणऽप्रशिष्टाः १०. ६६, २.

वरुणं १. २, ७; २३, ४; २५, ५;

८९, ३; १०६, १; १६४, ४६; ४. १, २; ५; २, ४; ३९, ४; ४१, ८; ९; ५. ४२, १; ६४, १; ६. २१, ९; ५०, १; ५१, ३; ७. ३९, ५; ६५, १; ६६, ७; ८२, ५; ८३, ६; ८४, ५; ८५, ३; ९३, ७; ८. १८, २०; ४२, २; ९. ९०, ५; ९५, ४; १०. १४, ७; ६३, ९; ७०, ११; ८९, ९.

वरुणंऽइव ६. ४८, १४.

वरुणयोः ६. ५१, १; ७. ६६, १.

वरुणऽशेषसः ५. ६५, ५.

वरुणस्य १. २४, १०; ४१, ७; ९१, ३; ९४, १२; १०५, ६; ११५, १; ५; १२३, ५; ८; १२८, ७; १३६, २; १५२, ४; १८४, ३; २. २७, ७; २८, १; ४; ३. ५५, ६; ६१, ७; ४. १, ४; ५, ४; ३३, ९; ४२, १; ५५, ७; ५. ८५, ५; ६. ४७, २८; ७०, १; ७४, ४; ७. ४४, ३; ६१, ४; ६२, ४; ६३, १; ८२, ६; ८४, २; ८७, ३; ८८, २; ८. १९, ४; २५, १७; ४१, ४; ७; ९; ४२, १; ४७, ९; ९. ७३, ९; १०७, १५; १०. १०, ६; ३०, १; ३६, ३; १३; ३७, १; ८५, २४; ८९, ८; १०३, ९; १२३, ६; १६७, ३; १८५, १.

वरुणा ४. ४१, २; ३; ६.

वरुणा ४. ४१, १; ४; ५. ६२, ३; ६; ६४, ६; ६. ६८, ५; ७. ६१, १.

वरुणानी ५. ४६, ८.

वरुणानीं १. २२, १२; २. ३२, ८.

वरुणाय १. १२९, ३; १३६, ४–६; १३७, २; ४. ३, ५; ४२, ७; ५. ५, ११; ६६, १; ६८, १; ८५, १; ६. ६८, ९; ७. ६०, १; ६२, २; ८५, १; ८८, १; ८. ४१, १; ९. ३३, ३; ३४, २; ६१, १२; ६५, २०; ७०, ८; ८४, १; ८५, ६; १००, ५; १०४, ३; १०८, १६; १०. १२, ८; ६५, ५; ६; ८; ८५, १७; ११३, ५.

वरुणे १. १५२, ५; ४. १, ३; ५. ४२, २; ४९, ५; ७२, १; ७. ८६, २; ८७, ७; ८. २७, ३; १०१, ५; ९. ६१, ९; १०. ३६, १२.

वरुणेन ४. ३४, ७; ३९, ३; ८. ३५, १.

वरुण्यात् १०. ९७, १६.

वरुता १. १६९, १; २. २०, २; ४. ५५, १; ६. २५, ७; ७. २१, ८.

वरूत्री ५. ४१, १५; ७. ३८, ५; ४०, ६.

वरूत्रीः ३. ६२, ३.

वरूत्रीभिः ७. ३४, २२.

वरूत्रीं १. २२, १०.

वरूथं १. २३, २१; ५८, ९; ११६, ११; १४८, २; १८९, ६; २. ३४, १४; ४. ५५, ४; ५. ४९, ४; ७. ३०, ४; ३२, ७; ५३, २; ८८, ६; ८. १८, २०; २७, ९; ६७, ३; ६; ७९, ३; १०. २७, १३.

वरूथे २. १८, ८; ७. २०, ८.

वरूथैः ४. ५६, ४; ७. १९, ७; १०. ६१, १७.

वरूथ्यः ५. २४, १.

वरूथ्यं ५. ४६, ५; ६. ६७, २; ८. ४७, १०; १०१, ५.

वरूथ्या ८. ४७, ३.

वरे ३. २३, ४; ५३, ११; ८. ९७, १०.

वरेण २. १०, ६; ७. ५, २.

वरेण्य ५. २५, ३.

वरेण्यः १. २६, २; ३; ७; ६०, ४; १७५, २; २. ७, ६; ३. २७, ९; ५. १३, ४; ८१, २; ८. २७, १२; ४६, ८; ६१, १५; ९. ६१, १९; १०. ९१, १; ११३, २; १२२, ५.

वरेण्यक्रतो इति वरेण्यऽक्रतो ८. ४३, १२.

वरेण्यं १. ९, ५; ५८, ६; ७९, ८; १५९, ५; ३. २, ४; १२, १; २७, १०; ३४, ८; ४०, ५; ६२, ६; १०; ५. ८, १; ३५, ३; ३९, २; ६. १६, ३३; ८. १, १९; १५, ७; २७, १; १०२, १८; ९. ६५, २९; १०. ३५, ७.

वरेण्यस्य ५. २२, ३.

वरेथे इति ८. ७३, ८.

वरेभिः १०. ३२, १.

वरेऽयं १०. ८५, १५; २३.

वरेऽयवः १०. ७८, ४.

वरेऽयात् १०. २७, ११.

वरो इति ८. २३, २८; २४, २८; २६, २.

वर्क् १. ६३, ७.

वर्के ६. २६, ३; ८. ७५, १२.

वर्क्त १. १८३, ४; ६. ५९, ७.

वर्गिति वर्क् १०. ८, ९.

वर्चः ३. ८, ३; २२, २; २४, १; ९. ६६, २१; १०. १२८, १; १५९, ५.

वर्चसा १. २३, २३; २४; १०. ८५, ३९; ११२, ३.

वर्चसे ९. ६५, १८; १०. १८, ९.

वर्चिनः २. १४, ६; ४. ३०, १५; ७. ९९, ५.

वर्चिनं ६. ४७, २१.

वर्जति ८. १, २७.

वर्णः ९. ७१, ८.

वर्णं १. ७३, ७; ९२, १०; ९६, ५; १०४, २; ११३, २; २. ३, ५; ४, ५; ५, ५; १२, ४; ३४, १३; ३. ३४, ५; ९; ९. ६५, ८; ७१, २; ९७, १५; १०४, ४; १०५, ४; १०. १२४, ७.

वर्णे २. १, १२.

वर्णेन ४. ५, १३.

वर्णैः १०. ३, ३.

वर्णौ १. १७९, ६.

वर्ते १. १६५, १४.

वर्तता १. ८९, २; ६. ४१, २; १०. १९, ५; ८९, १२.

वर्तते १. १८३, ३; ४. ४३, ५; ८. ५, ३४.

वर्तते १. १८३, २; ४. ३६, १; ५. ६२, ४; ७७, ३; १०. ३७, ३; १०७, ११.

वर्तध्वं १०. १९, १.

वर्तनयः १०. ५, ४.
वर्तनिः १. १४०, ९; १०. १४४, ४.
वर्तनिऽभ्यां ७. ६९, ३.
वर्तनिं १. २५, ९; ३. ७, २; ४. ४५, ३; ५. ६१, ९; ७. १८, १६; ८. ६३, ८; १०. ६५, ६; १७२, १; ४.
वर्तनी १. ५३, ८.
वर्तनीः ४. १९, २.
वर्ततां १०. १९, ३; ९४, १४.
वर्तते ५. ५३, ७; १०. ११७, ५.
वर्तते १०. ३४, ९.
वर्त ६. ६२, ११.
वर्तमानः १. ३५, २.
वर्तमानं ४. २८, २; ५. ३०, ८; १०. २७, १९.
वर्तमानाः ५. ४०, ६.
वर्तय १०. १५६, ३.
वर्तय २. २३, ७; ४. ३२, १५; ७. १०४, १९; १०. १९, २; ६; $८^{२}$; १७४, १.
वर्तयः १. १२१, ९.
वर्तयत् १०. ९५, १२.
वर्तयंत २. ३४, ९.
वर्तयंतं ७. १०४, ४.
वर्तयति १०. १७२, ४.
वर्तयंते १०. ९५, १३.
वर्तयथ १. ३९, ३.
वर्तयध्यै ५. ४३, २.
वर्तयन् ५. ४८, ३.
वर्तयंति ७. ७९, २; १०. ११४, ६.
वर्तयंतु ७. ४८, १; ७१, ३.
वर्तयाते ५. ३७, ३.
वर्तयामसि ३. ३७, १; ८. ६८, १; १०. ५८, १.
वर्तवे २. २५, ३; ३. ३३, ४; ८. ४५, २९.
वर्तस्व १०. ९५, १७.
वर्तो १. ४०, ८; ४. २०, ७; ५. २९, १४; ८. १४, ४.
वर्ति ८. ६, ३८.
वर्तिः १. ३४, ४; ९२, १६; ११६, १८; ११७, २; ११९, ४; १८३, ३; १८४, ५; २. ४१, ७; ५. ७५, ७; ६. ६२, ३; १०; ६३, २; ७. ४०, ५; ६७, १०; ६९, ५; ८. ९, ११; १८; २२, १७; २६, १४; १५; ३५, ७; ८७, ३; १०. ३९, १३; १२२, ६.
वर्तिका १. ११७, १६.
वर्तिकां १. ११२, ८; ११६, १४; ११८, ८; १०. ३९, १३.
वर्तो १०. १०१, ९.
वर्तते इति १. १८५, १; ६. ९, १.
वर्त्मानि १. ८५, ३.
वर्ध ६. ३८, ४; ७. ९५, ६; ८. ७५, १३; ९. २९, ३; ६१, १५.
वर्ध ५. ५६, २; ६. १८, १; ८. ६०, १२; ९. ६१, २३.
वर्धः १. ७१, ६.
वर्धत् ५. ६२, ५; १०. ६१, २६.
वर्धत् ६. ३८, ३; ७. ६८, ९.
वर्धत १०. २२, १४.
वर्धत २. २, १; १०. २५, १०.
वर्धतः १. ५१, ९.
वर्धतं ४. ५०, ११.
वर्धतां ३. १, २.
वर्धतां १. १६४, २७; ६. २४, ७; ३७, ५.
वर्धति ८. १५, ८.
वर्धतु ४. ५३, ७.
वर्धतु ५. ३६, ५.
वर्धते २. १३, १; ९. ७५, १.
वर्धते १. ९५, ५; २. २५, २; ३५, ११; ७. १०१, ३; ९. १७, ४; १०. ९४, ९.
वर्धन् ६. ५१, ११.
वर्धनः ३. ३२, १२; ७. १०१, २; ९. ९७, ३९; १०. ९१, १२.
वर्धनं १. १०, ५; ८०, १; ११४, ६; १४०, ३; २. १२, १४; १३, ६; ६. २३, ५; ८. १, ३; ९२, ५; १०३, १; १०. ४९, १; ६९, २.
वर्धना १. ५२, ७; ५. ७३, १०; ७. २२, ७; ८. ६२, ४.
वर्धना ८. ८, ५.
वर्धनानि २. ३९, ८; ६. २३, ६.
वर्धनी १०. ४, ७.
वर्धनेभिः ३. ३६, १.
वर्धत ५. १९, ३.
वर्धतः ९. ८, १; ६३, ५; १०. २०, ८.
वर्धतां ५. ४१, १४.
वर्धतां ५. ४१, १४.
वर्धति १. ६५, २; ३. ५, ८; ८. २, २९; ९८, ८; ९. ३१, ३; १०. ४३, ७.
वर्धति १. १५५, ३; ५. १३, ५; २२, ४; ३९, ५; ६. १, ५; ७. १२, ३; ८. ६, ३१; १६, ९; ६२, १; ९. ४६, ३; १०. ४३, ३.
वर्धतु ३. ५२, ८; ७. ९९, ७.
वर्धतु १. ५, ८; ३. १०, ६; ८. ३, ३; ८, २२; १३, १६; १८; ४४, १९; २२; ९. ६१, १४.
वर्धते १. १४०, ७.
वर्धमानः ३. ८, ५; ६. ९, ४; १०. १४२, ६; १६१, ४.
वर्धमानं १. १, ८; २. ३, ४; ३. ३०, ८.
वर्धमानाः ३. ३८, २.
वर्धय ६. १०, ७; ४९, १०; ९. ९७, ३६.
वर्धय १. १०, ४; १०३, ३; १२५, ३; १९०, १; ३. २९, १०; ५. १०, ३; ८. ६, ३२; ९७, १; ९. ४०, ५; १०. १४१, ६.
वर्धयत् १०. २५, १०.
वर्धयंतं १. ११८, २; ५. ६२, ३.
वर्धयन् ३. ६२, १५; ६. २८, २; ८. १९, ३३; ३६, ७; ३७, ७; ९. ५१, ४.
वर्धयंतः २. ११, ४; ८; १३; १०. ६७, ९; १०.
वर्धयंतं १०. ४९, ६.
वर्धयंति १. ५४, ८; २. ११, १; २७, १२; ५. ११, ५; ६. ४४, ५; ७. ५७, ७; ७७, ६; १०. २०, ३; २८, ६; १२०, ९.
वर्धयंति ८. १००, ४.

वर्धयंती ६. ६१, १२; ७. ९९, ६; १०. ४, ३.
वर्धयंती इति १०. ५, ३.
वर्धयंतीः १. ७१, ३; ६. ३४, ३.
वर्धयंतु २. ११, ११.
वर्धयमानः १. १२५, १.
वर्धयस्व १०. ५९, ५.
वर्धयामः १. ९१, ११.
वर्धयामसि १. ३६, ११; ६. १६, ११.
वर्धसे ५. ४४, १.
वर्धसे २. १, ११; ३. ४४, २.
वर्धस्व ३. ३६, ३; ५. ४४, ५; ८. १३, २५; ४४, २.
वर्धस्व ७. ८, ५; ८. १, १८; ६, १२; ७४, ८; १०. ९८, १०; १०४, २.
वर्धाः १०. ५०, ५.
वर्धात् ५. ४१, ९; ६. ३८, ४[२].
वर्धान् १. ७०, ४; ६. १७, ११; ३८, ४; ८. ७, १९.
वर्धाम १०. ४४, २.
वर्धाय १०. १२, ४.
वर्धासे ६. १६, १६.
वर्धिता ९. ९७, ३९.
वर्धते इति ५. ६८, ४.
वर्धथां ३. ५३, १.
वर्पः १. १४०, ५; ७; ३. ५८, ९; ४. १६, १४; ६. ३, ४; ७. ६८, ६; १००, ६.
वर्पऽनीतीः ३. ३४, ३.
वर्पसः १. १४१, ३; ५. ४८, ४; ८. ४६, १६; १०. १००, ७.
वर्पसा १. ३९, १; १०. ३, २; ९९, ३; ११.
वर्पांसि १. ११७, ९; ६. ४४, १४; ९. ९७, ४७.
वर्म १. ११४, ५; ६. ७५, ८; १९; ७. ३१, ६; ९. ६७, १४; ९८, २; १०. १६, ७; १०१, ८; १०७, ७.
वर्मऽइव १. ३१, १५; १४०, १०.
वर्मणः ६. ७५, १.
वर्मणा ६. ७५, १८.
वर्मण्ऽवंतः १०. ७८, ३.
वर्मऽसु ८. ४७, ८.
वर्मिणः ६. २७, ६.
वर्मी ६. ७५, १.
वर्मीऽइव ९. १०८, ६.
वर्वर्ति १. १६४, ११.
वर्वृतति ६. ४६, १४.
वर्वृतानाः १०. ३४, १.
वर्षथः ८. ५, २१.
वर्षऽनिर्निजः ३. २६, ५; ५. ५७, ४.
वर्षति ५. ८४, ३.
वर्ष ५. ५८, ७; ८३, १०.
वर्षयतं ५. ६३, ६.
वर्षयथ ५. ५५, ५.
वर्षयथः ५. ६३, ३.
वर्षयन् ९. ९६, ३.
वर्षिष्ठः १. ३७, ६.
वर्षिष्ठऽक्षत्रौ ८. १०१, २.
वर्षिष्ठं १. ८, १; ३. १३, ७; २६, ८; ५६, २; ४. ३१, १५; ५. ६७, १; ८. ४६, २४.
वर्षिष्ठया १. ८८, १.
वर्षिष्ठस्य ३. १६, ३.
वर्षिष्ठा ४. २२, ९.
वर्षिष्ठानि ८. ७७, ९.
वर्षिष्ठां ६. ४७, ९.
वर्षिष्ठाय ५. ७, १.
वर्षिष्ठे ६. ४५, ३१; ९. ३१, ५.
वर्षिष्ठेभिः १०. ३, ५.
वर्षिष्ठैः ९. ६७, २६.
वर्षीयः ६. ४४, ९.
वर्ष्मणा १०. १२५, ७.
वर्ष्मन् ३. ५, ९; ८, ३; ४. ५४, ४; १०. २८, २; ७०, १.
वर्ष्माणं ६. ४७, ४; ८. ३२, ३; १०. ६३, ४.
वर्ष्यं ५. ८३, ३.
वर्ष्यस्यऽइव १०. ९१, ५.
वर्ष्याः १०. ९८, ५.
वर्ष्यान् ५. ८३, ३.
वर्हि ३. ५३, १७.
वलः ३. ३०, १०; ८. २४, ३०; १०. ६८, १०.
वलं १. ६२, ४; २. ११, २०; १४, ३; १५, ८; २४, ३; ३. ३४, १०; ४. ५०, ५; ६. १८, ५; ८. १४, ७; ८; १०. ६२, २; ६७, ६; १३८, १.
वलंऽरुजः ३. ४५, २.
वलस्य १. ११, ५; ५२, ५; २. १२, ३; ६. ३९, २; १०. ६८, ५; ६; ९.
वल्गु ८. ७३, ८; १०. ६२, ४.
वल्गुऽयति ४. ५०, ७.
वल्गू इति ६. ६२, ५; ६३, १; ७. ६८, ४.
ववक्ष ३. ७, ६; ४. ७, ११; १०. ११५, १.
ववक्षतुः ८. १२, २५.
ववक्षि ८. ४५, ६.
ववक्षिथ २. २४, ११; ८. १२, ४–६.
ववक्षिथ १. ८१, ५; १०२, ८; २. २२, ३; ३. ९, ३; ८. १३, ७; ८८, ५.
ववक्षिरे २. ३४, ४.
ववक्षुः १. ६४, ३; ८. १२, ७.
ववक्षे ४. १६, ५; २३, १; ७. १००, ६; ८. ९३, ९.
ववक्षे १. ६१, ९; १४६, २; ३. ५, ८; ७. ८, २.
ववनः ४. ११, २.
ववंथ ८. १३, ३३; ६६, ५.
ववंद ६. ५१, १२; ६३, ३.
ववंदिम ५. २५, ९.
ववंदिरे ३. ५४, ४.
ववंदे १०. ६५, १५.
ववंधि ५. ३१, १३.
ववन्म ७. ३७, ५.
ववन्वांसा १०. ६१, ४.
ववन्वान् १०. २७, ९.
ववर्जुषीणां १. १३४, ६.
ववर्त ६. ६३, १; १०. ९३, १३.
ववर्त १. १६५, २; ५. ६२, २.
ववर्तत् ८. ९७, १३.
ववर्तत् ४. २४, १; ४४, ३.
ववर्तति ८. १०३, ११.
ववर्तति ८. ८८, ४; १०. ६४, १.
ववर्थ ३. ४३, ७.

ववर्थ १. ९१, २२.
ववर्धं ५. २, २.
ववर्ध ३. १, ११; १०. ८, १.
ववर्ह २. २३, १३.
ववव्रुषः १. १७३, ५.
ववसानस्य १. ५१, ३.
ववसाना १. ४६, १३.
ववसानाः ६. ११, ६.
ववसाने इति १०. ५, ४.
ववसे ८. ४, ८.
ववाच १. ६७, ४.
ववाता ४. ४, ८; ८. ४, १४.
ववातुः ८. १, ८; १६.
ववान ६. २३, ५; १०. ७४, ६.
ववार १. ३२, ११.
ववाशिरे २. २, २.
ववृक्तं ६. ६२, १०.
ववृजुः १. ३३, ५.
ववृजे ७. ३९, २.
ववृज्युः ८. ७९, ५.
ववृतन् ६. १७, १०.
ववृतीत ७. ६८, ४.
ववृतीमहि १. १३८, ४.
ववृतीय १. १८०, ५; १८६, १०; ७. ९३, ६.
ववृतुः १. १०५, १०; ४. ३०, २; ८. ४६, २३.
ववृते १. १६४, १४; १६६, ९; १९१, १५; ८. १०३, २; १०. ३३, ९.
ववृत्तन ५. ६१, १६.
ववृत्याः १. १७३, १३; ६. ११, १; ५०, ९; ७. ४२, ३; १०. ७३, ३.
ववृत्यात् १. १०७, १; ६. १७, १३; ३८, २; १०. ८९, २.
ववृत्यां ८. ७, ३३.
ववृत्यां १. ५२, १; १५२, ७; १६८, १; ३. ३२, १३; ५. ४९, १; ७. ३६, ४; ८४, १; १०. १०, १.
ववृत्याम ७. २७, ५.
ववृत्युः १. १३५, ५; १०. २६, ८; २७, ६.
ववृत्स्व २. १६, ८; ३. ३२, ५; ६१, ३; ४. १, २; ३; ३१, ४; ६. १९, ३; १०. ८३, ६; ९८, २.

ववृधतुः ७. ९७, ८.
ववृधते १०. ६४, ४.
ववृधध्यै १. ६१, ३; १२२, २; ६. ६७, १; १०. ९९, १.
ववृधंत ५. ५२, ७; ६. ६६, २; ६८, ४.
ववृधंत १०. ९३, १२.
ववृधंतः ४. २, १७.
ववृधस्व ६. १७, ३.
ववृधस्व १. ३१, १८; ७. १९, ११; १०. ११६, ६.
ववृधाति १. ३३, १.
ववृधाते इति ७. ७, ५; ८. १२, २८.
ववृधाते इति १०. ५, ४.
ववृधानः १. १३१, ७; २. ११, २; ४; २०; १९, १; ३. ३४, १; ४५, ५; ४. २१, १; ५. २, १२; ३, १०; १२; ८, ७; २७, २; ७. ५, २; ८. ६, ४०; ५३, २; ७६, ३; १०. १४, ३; ५४, २; ७९, ७; ८१, ६; ११६, ६; १२०, २.
ववृधानं १. १७३, १; ३. ४७, ५; ५१, १; ४. ३, १४; ५. ३२, ६; ६. २२, ६; ३८, ५; ७. १, १२; १०४, ४; ९. ८५, १०.
ववृधानस्य ८. १४, ६.
ववृधाना १. ९३, ६; ११७, ११; ६. ६९, ६; ८. ५, ११.
ववृधानाः ८. ९६, ८; १०. ७८, ८.
ववृधानान् ५. ४२, ९.
ववृधानाय ९. ४२, ३.
ववृधानौ ५. ६९, १; ८. ८७, ४.
ववृधीथाः १. १३०, १०.
ववृधुः २. २०, ४; ८. २२, १२; ९५, ६; ९. ९, ४; १०. १४, ३; ६६, १.
ववृधुः २. ८, ५; ३४, १३; ५. १४, ६; ५५, ३; ५९, ५; ६; ६०, ५; ६. ३४, ४; ७. ६०, ५; ८. ६, २१; ३५; ४३; १२, २०; ६२, १०; ९. १०६, ८; १०. ७३, २; ७७, २; १२२, ७.
ववृधे १. १६७, ८; ३. १, ८; ३२, १३; ६. १९, २; ४४, १३; ७. ५, १; १०. २३, ५; ३०, ४.

ववृधे १. ३७, ५; ५२, २; ७; ८१, १; ४; १४०, २; १४१, ५; २. २२, २; ३. ५, २; ३६, १; ५; ४०, ७; ६. १९, १; ३०, १; ७. ९५, ३; ८. ३, ८; ६, १; १२, ८; ९; ११; ४४, १२; ६२, २; ९. ८९, २; ९७, ४०; १०. २९, ७; ६१, २१.
ववृधेन्यं ८. २४, १८.
ववृध्वं ८. २०, १८.
ववृध्वांसं ८. ९५, ७; ९८, ८.
ववृमहे ६. ४, ७; ८. २१, २.
ववृमहे १. १८७, २; ३. ९, १; ८. १९, ३.
ववृषस्व ८. ६१, ७.
ववृषाणाः ६. २६, १.
ववृषे ९. ८८, १.
वव्रे १. ६१, १५.
वव्रे १. ३६, १७; ५. ७४, ७.
वव्रः १. ५२, ३.
वव्रं ५. ३२, ८.
वव्रयामहे ८. ४०, २.
वव्राजं ३. १, ६.
वव्रान् ७. १०४, १७.
वव्रासः १. १६८, २.
वव्रिः ५. १९, १; १०. ४, ४.
वव्रिणा १. ५४, १०.
वव्रिं १. ४६, ९; ११६, १०; १६४, ७; २९; ५. ७४, ५; ९. ६९, ९; ७१, २; १०. ५, ५.
वव्रिऽवांसं २. १४, २; ३. ३२, ६; ४. १६, ७; ६. २०, २; ९. ६१, २२.
वव्रुः ७. ९०, ४.
वव्रुरिति वव्रुः ४. १, १५; १६, ६.
वव्रे ४. १, १३; ५. ३१, ३; ७. १०४, ३; १०. ८, ७.
वव्रे १. ६२, ७; ३. ३८, ८.
वव्रेः ४. ४२, १; ५. १९, १.
वशः १. ९१, ६; १२९, १; ८. ४६, २१; ६१, ४; ९३, १०.
वशंत ८. ६६, ४.
वशाऽनीः १०. १६, २.

वशौंति ८. २०, १७; २८, ४.
वशं १. ११२, १०; ११६, २१; ८. ८, २०; ४६, ३३; ५०, ९; १०. ४०, ७; ६६, ९; ८४, ३; १७१, ४.
वशंस्य ६. २४, ५.
वशा २. २४, १३.
वशाऽअंन्नाय ८. ४३, ११.
वशाः ६. १६, ४७; १०. ९१, १४.
वशान् १. ८२, ३; १८१, ५; ८. ४, १०; १०. ९१, ७; १४२, ७.
वशानां ३. ६०, ४.
वशाभिः २. ७, ५.
वशाम १. १६५, ७.
वशासः ६. ६३, ९.
वशिनीं १०. ८५, २६.
वशी १. १०१, ४; ३. २३, ३; ४. ५३, ६; ८. १३, ९; ६७, ८; १०. ८४, ३; १०३, ३; १५२, २; १९०, २.
वशे ८. ९३, ४; ९. ८६, २८.
वशैः ८. ८१, ९.
वश्मि २. ३१, ७; ३३, १३; ३. ३१, १४; ५. ४६, १; ८. १, १६; ९. ९६, ४.
वषट् ७. ९९, ७; १०. ११५, ९².
वषट्ऽकृतं १. १६२, १५; २. ३६, १; १०. १७, १२.
वषट्ऽकृतस्य १. १२०, ४.
वषट्ऽकृताः ८. २८, २.
वषट्ऽकृति १. १४, ८.
वषट्ऽकृतिं १. २१, ५; ७. १४, ३; १५, ६.
वष्ट्यः ५. ७९, ५.
वष्टि १. ३२, ३; २. २४, ८; ४. २२, १; ५. ८५, ४; ६. ११, ३; ८. ४५, ६; १०. ९५, ४.
वष्टि १. १२७, १; २. १४, १; २५, ३; ३७, १; ४. १, ८; २५, २; ५. ३४, ५; ६. ६१, ७; १०. १०, २; १२; ४२, ४.
वष्टु १. ३, १०.
वसः ७. ८, ३.
वसत ५. ५२, ९; ६३, ६; ८५, ४.
वसतः ६. ३८, २; ८. २९, ८.
वसति २. १०, ३.
वसतिः ६. ३, ३; १०. ९७, ५.
वसतिं १. ३३, २; ५. २, ६; १०. १२७, ४.
वसतीः १. २५, ४.
वसंते १०. ८८, १९.
वसते १०. ६३, ४; १३६, २.
वसतेः १. १२४, १२.
वसतौ १. ३१, १५.
वसतौऽइव ९. ६२, १५.
वसत्या १. ६६, ५.
वसंन् १०. १४६, ४.
वसंना १. ९५, ७.
वसंतः १०. ९०, ६.
वसंतान् १०. १६१, ४.
वसर्हा १. १२२, ३.
वसंवः ३. ८, ८; ५. ४१, ९; ६. ५०, ४; १५; ७. १, २; ५, ६; ११, ४; ३८, ३; ३९, ३; ४८, ४; ५६, २०; ८. ५४, ३; ९. ६७, २७; १०. ६६, १२; १२८, ९; १४२, ६.
वसवः १. १०६, १–६; १६३, २; २. ३, ४; २७, ११; २९, ३; ३४, ९; ३. ३९, ८; ५७, २; ४. १२, ६; ५५, १; ५. ४१, १८; ५५, ८; ६. ५१, ५; ७; ६२, ८; ७. ५२, १; २; ५६, १७; ५९, ८; ८. १८, १५; १७; २७, २; ९; २०; १०. ३७, १२; ७७, ६; १००, ७; ९.
वसवान १०. २२, १५.
वसंवानः १. १७४, १.
वसवानः ५. ३३, ६.
वसंवानं ८. ९९, ८.
वसंवानाः १. ९०, २.
वसंवे ५. ३, १२; ९. ८१, ३; १०. ९१, १२.
वसव्यं २. ९, ५; १३, १३; १४, १२; १०. ७४, ३.
वसव्यस्य ४. ५५, ८; ६. ६०, १.
वसव्या ७. ३७, ३.
वसव्ये ७. ५६, २१.
वसव्यैः ६. १, ३; १३, ४; ६०, १४.
वसाथे इति १. १५२, १.
वसानः १. १३५, २¹; १६४, ३१; २. १०, १; ३०, ३; ३५, ९; ३. १, ५; ३८, ४; ४. ५, १५; १८, ५; ५. ४३, १३; ४८, ५; ६. २९, ३; ९. ७, ४; ४२, १; ७८, १; ८०, ३; ८२, २; ८३, ५; ८६, १४; ४०; ९०, २; ९६, १३; ९७, २; १२; ४७; १०७, ४; १८; १०. १, ६; १६, ५; ५३, ३.
वसानं १. १५२, ४; ९. १६, २; १०९, २१.
वसाना १. १२२, २; १२४, ३; ३. ३९, २.
वसानाः १. १६४, ७; ४७; ३. ८, ९; ३८, ७; ७. ९७, ६; ९. ९४, ४; १०. ५, २.
वसां ५. २, ६.
वसायतें ९. १४, ३.
वसान्यां १०. ७३, ४.
वसिष्ठ २. ३६, १; ९. २, ३.
वसिंष्ठ ७. १, ८.
वसिष्ठ ७. २३, १; ३३, १०; ११; ८८, १; ९६, १.
वसिंष्ठः २. ९, १; ७. ९, ६; १८, ४; २१; २२, ३; २६, ५; ३३, ६; १२; १४; ४२, ६; ५९, ३; ७३, ३; ९५, ६; १०. ६५, १५; ९५, १७; १५०, ५; १८१, १.
वसिंष्ठं १. ११२, ९; ७. ३३, १३; ७०, ६; ८६, ५; ८८, ४.
वसिष्ठऽवत् ७. ९६, ३.
वासिंष्ठस्य ७. ३३, ५.
वसिंष्ठाः ७. ७, ७; १२, ३; ३३, १; ७; ९; ३७, ४; ७६, ६; ७७, ६; ८०, १; ९०, ७; १०. १५, ८; १२२, ८.
वसिष्ठाः ७. ३३, ३; ४; ८.
वसिंष्ठान् ७. ३३, २.
वसिंष्ठासः ७. २३, ६; १०. ६६, १४.
वसिंष्ठैः ७. ३९, ७; ७६, ७.
वसिंष्व १. २६, १.

वसिष्व ८. ७०, १०.

वसीमहि ९. ७२, ८.

वसु १. १०, ६; ३१, ९; ४०, ४; ४१, ६; ४६, ९; ४७, ३; ६; ९; ५१, ३; ४; ५३, ३; ५५, ८; ८१, २; ६; ७; ८४, ७; १७६, ३; २. ५, १; १३, ११; २२, ३; २३, ९; ३. २, ११; १३, ४; ७; ४५, ४; ६२, ३; ४. ८, ३; ३१, २; ८; ५. १७, ४; ३४, ७; ५७, ३; ६. १, १३; १६, ३३; २३, ३; ४७, २२; ४८, १५^{2}; ५१, १६; ५३, २; ५४, ४; ५९, ९; ७. १२, ३; १८, १; २०, २; ३२, १५; १६; २१; २५; ५९, ६; ९४, ९; ८. २, ३५; ४, १६; ६, ४१; १७, १०; २१, १७; २३, ३; ३२, ८; ४०, ४; ६; ४३, ३३; ४४, १५; ४५, ४०; ४६, १५; ५०, १; ५३, ४; ६६, ४; ६; ८८, ३; १००, ६; १०१, ६; १०३, ६; ११; ९. १९, १; २२, ७; ३६, ५; ५७, ४; ६४, ६; ८१, ३; ९०, १; ९८, ४; १११, २; १०. २३, २; ३६, ११; ४५, ११; ४८, ५; ४९, १; ५५, ६; ६२, २; ६६, १४; ७७, १; ८५, २९; ८६, ३; ९५, ४; १३३, ३; १३८, ४; १५१, ४.

वसुः १. ४३, ५; ६०, ४; ७९, ५; ९४, १३; ११०, ७; १२८, ६; १४३, ६; ४. ४०, ५; ५. ६, १; २; २४, २; २५, १; ५१, १३; ६. २४, २; ४४, १५; ४५, २३; ८. १९, ३७; २४, ३; ४४, २४; १०३, १२; १०. २२, १५; ३२, ८; ४५, ५; ९१, ३; ११५, ७.

वसुऽजुवं ८. ९९, ८.

वसुता ६. १, १३.

वसुऽतातिः १. १२२, १२.

वसुऽतातिं १. १२२, ५.

वसुत्तये ८. ६१, ७; ९. ४४, ६.

वसुऽत्वनं ७. ८१, ६; ८. १३, १२.

वसुऽत्वना ८. ५०, ६.

वसुऽत्वनाय ८. १, ६.

वसुऽत्वा १०. ६१, १२.

वसुऽदां ८. ९९, ४.

वसुऽदावन् २. ६, ४.

वसुऽदावा २. २७, १२.

वसुऽदेयाय १. ५४, ९; २. ३५, ७; ६. ३९, ५.

वसुऽधितिं १. १२८, ८; ४. ८, २; ७. ९०, ३.

वसुधिती इति वसुऽधिती १. १८१, १; ३. ३१, १७; ४. ४८, ३.

वसुनः १. ५३, २; १०९, ५; १४९, १; २. १६, ७; ६. १९, ५; ७१, २; ७. ३७, ३; ८. १, ३१; ९. ७२, ८; १०. ४८, १; ५०, ७.

वसुना १. ८३, १; १२५, २; ३. ५५, २०; ४. २०, ६; ६. ३, ७; ७. ३७, ३; १०. ४२, २.

वसुऽपतिः ४. १७, ६; ६. ५२, ५; ७. ४५, ३; ८. ४४, २४.

वसुऽपतिं १. ९, ९; ३. ३६, ९; ५. ४, १; ८. ५२, ६; ६१, १०.

वसुऽपते २. ६, ४.

वसुऽपते १. १७०, ५; २. १, ११; ३. ३०, १९; १०. ४७, १; ११२, १०.

वसुऽपत्नीं १. १६४, २७.

वसुऽभिः १. ५८, ३; ११०, ७; १४३, १; ६; २. ३१, १; ३. १९, २; ४९, ४; ५. ३, ८; ५१, १०; ७. ५; ९; १०, ४; ३५, ६; ४४, ४; ४७, २; ७६, २; ५; ९०, ६; ८. ३५, १; ९. ९३, ३; १०. ३, २; ६६, ३; ७९, ७; ९८, १; १०८, ७; ११०, ३; १२५, १; १५०, १.

वसुऽभ्यः ५. ४९, ५; १०. ८७, ९.

वसुं १. ४४, ३; १२७, १; ८. ७१, १३; १०. १२२, १.

वसुऽमत् ९. ६९, ८; ८६, ३८.

वसुऽमता १. ११८, १०; १२५, ३; ४. ४, १०; ७. ६७, ३.

वसुमती इति वसुऽमती ३. ३०, ११.

वसुऽमंतं १. १५९, ५; २. २४, २; ४. ३४, १०; ६. ६८, ६; ७. ७१, ३; ८४, ४; १०. ११, ८.

वसुऽमान् ७. ७१, ४.

वसुऽयंतः १. १३०, ६; ४. १६, १५.

वसुऽयवः १. ४९, ४; ६२, ११; १२८, ८^{2}; २. ११, १; ३. २६, १; ५. ३, ६; २५, ९; ७. ३२, २; ८. ५२, ६; ६१, १०; ९. ११२, ३; १०. २५, २; ४७, १; ९१, १२.

वसुऽया १. ९७, २; १६५, १.

वसुऽयात् ८. ८, १६.

वसुऽयुः १. ५१, १४; १८६, ११; २. ३२, १; ५. २९, १५; ६. ५१, १२; ७. १, ६; ३४, २१; ६७, ४.

वसुऽयुं ४. ४४, १; ७. ६७, ५.

वसुऽरुचः ९. ११०, ६.

वसुऽरोचिषः ८. ३४, १६.

वसुऽवनिं ७. १, २३.

वसुऽवसु १०. ७६, ८.

वसुऽवाहनं ५. ७५, १.

वसुऽवित् १. १८, २; ९१, १२; १६४, ४९; ९. ८६, ३९; ९६, १०.

वसुवित्ऽतमं १. ४५, ७; ६. १६, ४१.

वसुऽविदः ८. ६०, १२; ९. १०१, ११.

वसुऽविदं ७. ४१, ६; ८. २३, १६; ६१, ५; ९. १०४, ४; १०. ४२, ३.

वसुऽविदा १. ४६, २.

वसुऽश्रवाः ५. २४, २.

वसू इति १. १५८, १; २.

वसू इति १. १२०, ७.

वसून् १. ४५, १; ३. २०, ५; १०. ६६, ४.

वसूनां १. ७, ९; ५८, ७; ७६, ४; ९४, १३; ९६, ६; १२३, ४; १२७, ७; १२८, ५; १६४, २७; १७०, ५; २. ११, १; ३. ३०, १९; ३६, ९; ४. १७, ६; ५. ४, १; ३६, १; ६. ४७, ६; ५२, ५; ७. ७, ७; १६, २; २४, ५; २५, २; ३२, ५; ४३, ४; ७५, ५; ८. ३१, १४; ३९, ४; ४६, १६; ५२, ५; ६८, ६; ७१, ८; १०१, १५; ९. ५८, २; ९३, ४; १०८, १३;

१०. ४७, १; ४८, ११; ५०, ७; ७४, १; ९१, ३; १२५, ३.

वसूंनि १. १५, ८; ४२, १०; ५९, ३; ६७, ४; ८४, २०; १२३, ६; १३४, ४; २. ३०, १०; ३२, ५; ३. ५१, ५; ५५, २०; ५६, ६; ४. २४, १; ३३, ११; ५. ४२, ३; ६१, १६; ६. १, १३; ५, २; ३; ७, ३; १६, ४८; ३०, १; ३१, ४; ४५, ८; २०; ७३, ३; ७. ६, ७; ११, ३; २४, १; २७, ३; ३४, २२; ४५, ३; ७७, ४; ७९, ३; ८४, ४; १०३, १०; ८. १२, २१; ७८, ८; ९९, ३; ९. ७, ९; १४, ८; १५, ६; १८, ४; २९, ४; ६२, ११; ६३, ३०; ६४, १८; ६५, २; ६९, १०; ८८, २; ९७, ५१–५३; १००, २; ३; १०८, ११; १०. ६, ६; २१, ६; ४४, ५; ४६, १; ५४, ५; ६९, ६; ८३, ३; १११, १०; १८०, १; १९१, १.

वसो इति २. ७, १; ३. १५, ३; ५७, ६; ६. २, १; १६, २४; ४८, ९; ८. १९, १२; ३३, २; ९. ९८, ५; १०. ७, २.

वसो इतिं १. १०, ४; ३०, १०; ३१, ३; ४५, ९; ८४, २०; १२९, ११[२]; २. १३, १३; १४, १२; ३७, ६; ३. १८, २; २१, ५; ४१, ७; ५१, ६; ४. ३२, १४; ५. ३, १०; ६. १, १२; १६, १८; ४६, ६; ७. ३१, ३; ४; ८. १, ६; २९; २, १; ४, १७; १९, २६; २८; २९; २१, ८; २३, २८; २४, ७; २६, २०; ४४, ३०; ४६, ९; ५०, ३; ४; ९; ५१, ६; ५२, ८; ६०, ४; ९; ६६, १२; ७०, ९; ७१, ९; ७८, ३; ९८, ११; १०३, ४; १३; १०. ८, ४; ३८, २; ९३, ११; १०५, १.

वसोः १. ९, ९; २२, ७; ३. ५१, ३; ४. ५, १५; ६. ५५, ३; ८. २४, ८; ८१, ६; ८८, १; १०. ६१, १२.

वसौ १. ८१, ३[२]; ४. १७, १३; ८. १३, २२.

वस्त १. २५, १३.

वस्तंवे १. ४८, २.

वस्ता ३. ४९, ४.

वस्तां ६. ७५, १८.

वस्तुः ८. ७१, १५.

वस्तुंपु ८. १९, ३१.

वस्तें ४. २५, २; ५. ४९, ३; ७. ६९, ५; ८. ४६, २६.

वस्ते ३. ५५, १४; ६. ३, ६; ४, ३; ७५, ११; १०. ७५, ८; ११४, ३.

वस्तोंः १. ७९, ६; १०४, १; ११६, २१; १७७, ५; १७९, १; २. ३९, ३; ४. १६, ४; ४५, ५; ५. ३२, ११; ६. ४, २; ५, २; ३९, ३; ७. १, ६; १०, २; ८. २५, २१; १०. ४०, २; ४; ११०, ४; १८९, ३.

वस्तोंःऽवस्तोः १०. ४०, १; ३.

वस्त्रऽदाः ५. ४२, ८.

वस्त्रऽमथिं ४. ३८, ५.

वस्त्रा १. १३४, ४; ५. ४७, ६; ६. ४७, २३; ९. ९६, १; ९७, २; ५०; १०. १०६, १.

वस्त्राऽइव ५. २९, १५; ८. १, १७.

वस्त्राणि १. २६, १; १५२, १; ३. ३९, २; ९. ८, ६; १०. १, ६.

वस्त्रेणऽइव १. १४०, १.

वस्त्रैः २. १४, ३.

वस्नं ४. २४, ९.

वस्नऽयंता ६. ४७, २१.

वस्न्यंस्य १०. ३४, ३.

वस्मं ४. १३, ४.

वस्मंनः २. ३१, १.

वस्यः १. ३१, १८; १०९, १; १४१, १२; २. १, १६; २, १३; ९, २; ३९, ५; ४. २१, ४; ५. ३१, २; ५५, १०; ६. ४४, ७; ४७, ७; ६१, १४; ७. ३२, १९; ८. १६, १०; २१, ९; २७, २२; ४८, ९; ७१, ६; १०. ४५, ९; ९२, १३.

वस्यःऽइष्टये १. २५, ४; १७६, १; ८. ८६, २; ३.

वस्यंसः २. १७, ८; ४. २, २०; ८. ४८, ६; ९१, ४; ९. ४, १.

वस्यंसा ८. २०, १८.

वस्यंसाऽवस्यसा १०. ३७, ९.

वस्यंसी ५. ६१, ६.

वस्यांन् ६. ४१, ४; ८. १, ६.

वस्वंः १. २७, ५; ५१, १; ७१, ९; ९०, २; ११३, ७; १४३, ४; २. १, ७; २, १२; १४, ११; २०, ४; ३. ४, १; १९, ३; ४३, ५; ४. १७, ११; २०, ८; २१, १०; ४१, ९; ५२, ३; ५. १५, १; ३४, ४; ६. १९, १०; ३६, ४; ७. ६, ४; १५, ४; २०, ९; ३९, १; ८२, ४; ८३, ५; ६; ९७, १०; ९८, ६; ८. १४, १; ३९, १०; ४०, ९; ७१, ९; ८१, ४; ९. ९७, ४४; ९८, ५; १०. १५, ७; ३०, १२; ४३, ३; ७७, ६.

वस्वीं ६. १६, २५; ६४, १; ७. २०, १०.

वस्वीः १. ८४, १०–१२; ५. ४१, ६; ७४, १०; १०. २२, १२.

वस्वींभिः ३. १३, ५.

वस्व्यां १०. १७२, २.

वहं १. १३५, २; १७४, ५; १७५, ४; ७. ९०, १; ९. ६५, १७; १०. १२, २; ५१, ५; ११०, १.

वह १. १२, ३; १०; १३, १; ४; १४, १२; १५, ४; २२, ९; १०; ३१, १७; ४४, १; ७; ९; ४५, २; ४८, ११; १२; ७६, ३; ९२, १५; ९४, ३; १४२, १; ४; १८८, १; २. ३, ३; ११; ३२, ३; ३. ६, ६; ९; १९, ४; २५, २; ४. २, ४; ५५, ९; ५. २६, २; ५; ४३, ६; ६१, १७; ७९, ७; ८; ६. १५, १४; १६, ६; ४४; ६४, ४; ५; ७. १, २४; १०, ४; ११, ५; १६, ४; ९; १७, २; ३९, ५; ८. २३, ३०; ४४, ९; ४७, १४; १६; ६०, ४; ९३, २५; १०२, २; १०. १, ७; ११, ९; १६, ४; १२; ७०, ११; १५०, ३.

वहंत् ८. १, ११.

वहत १. २३, २२; ८. २०, २३; १०. ५३, ७.
वह॑तः १०. २३, ३.
वहतः ३. ७, ४.
वहतः १. ८४, २; १६५, ४; २. १०, २; ५. ४१, ७; ६. २०, ९; ८. १३, २३; ३३, १८; १०. २७, २३; ९६, ६.
वहं॑तं ८. ५, २०.
वहतं १. ३४, ४–६; १२; ४७, ६; ९२, १७; १५७, ४; ३. ५३, १; ५. ४२, १८; ७. ६९, ५; ८. ५, १५.
वहतात् १०. २४, ५.
वह॑तां ३. ४१, ९; ८. १७, २.
वहतां ८. १, २५; १०. ८५, २६.
वहं॑ति ४. ४४, १; ७. ६३, २; ६६, १४; ८. ७, २८.
वहति १. ३९, ६; १६४, २; ३. ५८, १; १०. ३२, ३; ४२, ८; १०२, २; १०.
वहतु ७. ३७, १; १०. १६, ९.
वहतुः १०. ३२, ३; ८५, १३.
वहतुनां १०. ८५, ३८.
वहतुं १. १८४, ३; ४. ५८, ९; १०. १७, १; ३२, ४; ८५, १४; २०; ३१.
वहतू इति ७. १, १७.
वह॑ते १. १६७, ७; ५. ३०, ३; ४४, ८; ८. ४६, २६.
वह॑त्ऽभ्यः १०. ९४, ७.
वहथ ६. ६५, ४.
वह॑थः १. ११९, ३.
वहथः १०. ४०, ४.
वह॑ध्यै १०. २२, ५.
वह॑ध्यै ५. ५३, १३; ६०, ७; १०. ७७, ६.
वह॑न् ५. ७७, ३.
वहं॑तः १. ३५, ५; ६९, ५; २. १४, ८; ७. ७५, ६; ९. ८३, १.
वहं॑तं १. ६५, १.
वहं॑ता १. ११६, १९; ५. ७६, ४; ६. ६२, ४; ७. ७०, ३; ७१, २.
वहं॑ति १. १४, ६; ५०, ८; ११३, २०; ११८, ४; १८६, ५; ४. २१, ८; ४४, २; ६. १६, ४३; ६४, ३; ७. ६०, ३; ६६, १५; ६७, ८; ७८, ४; ८. ३, २३; ५८, १; १०. ३१, ८; ३२, २; ३३, ५.
वहंति १. ५०, १; १६४, ३; १४; १९; ३. ७, ४; ५५, १८; ५८, २; ४. १३, ३; ७. १८, २३; ९०, ५; ९७, ६; ८. ७, ३५; १०. २८, ४; १०७, ११.
वहं॑तीः १. ९२, ३; २. ३५, ९; १४; ३. ७, २; ६. ६५, ३; ७. ७७, ३.
वहं॑तु १. ४७, ८; ४९, १; १३४, १; ४. ४६, ३; ४८, ४; ५. ३३, ८; ७. २४, ३; ८. १, २४; ३३, १४.
वहंतु १. १६, १; ८५, ६; ९२, १८; १०१, १०; ११८, ४; ५; १८१, २; ३. ४३, ६; ५३, ४; ६१, २; ४. १४, ४; ५. ३१, ९; ६२, ४; ७५, ६; ६. ३७, १; ४०, ३; ४४, १९; ५५, ६; ६३, ७; ६९, ४; ७. ४१, ६; ६७, ४; ८. ५, ३३; ६, ४२; ४६, ७; ६५, ४; १०. १४, ४; ४४, ३; ९६, १२.
वहं॑ते ५. ५८, १; ६१, ११; ८. २०, ७.
वह॑मानः ७. ४५, १; १०. ११, ७; ४९, ७.
वह॑मानं १०. २७, १९; ४०, १.
वह॑माना ५. ३१, ९.
वह॑मानाः १. १२३, १२; १७४, ६.
वह॑सि ६. ६४, ५; ७. ८१, ३.
वहसि १. १२४, १२; ८. ६०, १५.
वहसे ५. ३६, ५.
वह॑स्व ८. २६, २३[२].
वहा॑तः ३. ४३, ४.
वहातः ३. ३५, २.
वहा॑ते ५. ३७, ३; १०. २७, ११.
वहा॑थ १०. ६४, १२.
वहान् १. ८४, १८.
वहा॑नि १०. ५२, १.
वहा॑मि १०. ३३, १.
वहामि ५. ४६, १.
वहा॑सि १. ७४, ६.
वहासि १०. ५१, ७.
वहि॑ष्ठयोः ६. ४७, ९.
वहि॑ष्ठा १. १३४, ३; ५. ५६, ६.
वहि॑ष्ठाः ४. १४, ४; ६. २१, १२; ४०, ३; ६३, ७.
वहि॑ष्ठान् १. १२१, १२.
वहि॑ष्ठेभिः ४. १३, ४.
वहि॑ष्ठैः १०. ७०, ३.
वही॑यसः १. १०४, १.
वहेथां ७. ७१, ३.
वहे॑थे इति १. १८०, ९; ८. २६, १९.
वहेथे इति १. १३५, ८; १८२, २; ४. ४५, ३; ८. ५, ३१.
वहेयुः ६. ३७, ३.
वह्न॑यः १. ३, ९; १४, ६; २०, ८; ४८, ११; २. २४, १३; ३७, ३; ३. ६, २; ५. ७९, ४; ६. ५७, ३; ७. ८२, ४; ८. ३, २३; ६, २; १२, १५; १०. ११४, २; १३८, १.
वह्न॑ये २. २१, २.
वह्निः १. ७६, ४; ११३, १७; १२८, ४; १२९, ५[२]; १६०, ३; १८४, १; २. १७, ४; ३८, १; ३. ५, १; २०, १; ३१, १; ४. २१, ६; ५. ५०, ४; ६. ११, २; १६, ९; ७. ७, ५; १६, ९; ८. २३, ३; ९४, १; ९. ९, ६; २०, ६; ३६, २; ६४, १९; ८९, १; ९७, ३४; १०८, १०; १०. ११, ६; ६१, ९; १०१, ११.
वह्नि॑ऽतमः ४. १, ४.
वह्नि॑ऽभिः १. ६, ५; ४४, १३; ६. ३२, ३; ७. ७५, ५; १०. ९३, ९.
वह्नि॑ १. ६०, १; ३. १, १; ११, ४; ३१, २; ७. १६, १२; ८. ४३, २०; ९. ६५, २८; ९१, १; ९६, १७; १०. १०१, १०; ११५, ३.
वह्नी इति ७. ७३, ४; ८. ८, १२.
वह्ने ९. २०, ५.
वह्ने॑ः ६. ३९, १.
वह्येऽशयाः ७. ५५, ८.
वा १. ६, ९; १०[३]; ८, ६[२]; ११, ८;

२३, १७; २२; ३०, २^{२}; ३१, १८^{२}; ३६, १५; ४७, ६; ७; ५४, ७; ६८, ३; ७१, ६; ८३, ६^{२}; ८६, २^{२}; ३; ८; ९४, ९^{२}; १००, ११; १०१, ८; १०८, ७; १०९, १; २; ११२, १९; ११६, २^{२}; १२०, ७; १४२, १०; १४७, ५; १६१, ८; १६२, ८; ९; १७^{२}; १६३, १; १६४, २३^{२}; १६६, ५; १६७, २; १८०, ९; १८५, ८^{३}; १८९, ६; २. २, १०^{२}; ५, ३; १०, २; ११, १६; २३, ७; २८, १०^{४}; ३०, ९; ३४, ४; १०; ३. ४, ४; ६; ६, ६; ८^{२}; ९; ८, १; १०; २८, २; ३५, १०^{२}; ४. २, ६; ८; २१, ३^{२}; २५, १; २; २७, ३; ४१, २; ४४, ३^{३}; ४८, ५; ५१, ४; ५. ३, १२; १८, ४; ३४, ३ ; ५^{२}; ३५, २; ४१, १^{४}; २; ३; १५; १९^{२}; ४२, ५; ८; ४८, ३; ५२, ७^{२}; १४; ५३, १; ५४, ७^{२}; ६०, ६^{३}; ६२, ७; ६५, १; ६७, ५; ७३, १; ७९, १०^{२}; ८५, ७^{५}; ८; ६. ३, ८^{२}; १३, ४; १५, ११^{३}; २३, १; २^{२}; २४, १०; २५, ४^{२}; ६^{२}; २७, १; ४०, ५^{२}; ४५, ११; ४६, ७; ८; ४८, २०^{२}; ५०, ४; ५२, २^{२}; १३; ७. ३, ८^{२}; ७, ६; १६, ११^{२}; ३२, १; ३३, १२; ४२, २; ४९, २^{२}; ५५, ३; ८२, ८; ९८, ४; १०४, ९^{३}; १४^{२}; १५; १६; १८; ८. १, १८; ४, १; २; ५, २७; ३६; ९, ६; ९, १२^{२}; १९; २१; १०, १^{२}; २; ६^{२}; १२, १६^{२}; १७; १८^{२}; १३, १५; १९, ११; १२; १३^{२}; २०, १५; १६; २१, १७^{३}; २२, १५; २४, १६; २७; २६, १७; २७, १९; २०; ३१, १५; ३२, ६; ४३, २८; ४४, २३; ४७, १५^{२}; ४८, १५; ४९, ७^{२}; ६१, ९^{२}; ६५, २^{२}; ६६, ३; ७५, १४; ७८, १०^{२}; ९३, ५; ९७, ५; ९. ११, ७^{२}; ५२, ५; ६५, २२; २३; ७९, २; ९७, २२; ५४^{२}; १०८, १४; १०. १०, १४^{२}; ११, ५; १५, २; १६, ३; ६; १७, १२^{२}; २२, १^{२}; २७, ४; ६; ११; २९, १; ३१, ४; ३२, ५; ३३, ८; ३७, १२; ३८, ३; ४०, ३; १४^{२}; ४१, ३^{३}; ४८, ८; ५०, २; ६१, १८; ६४, ३; ५; ६९, १२; ७०, ५^{२}; ७४, १^{५}; ८६, ३; १०; ८७, ६^{२}; ९१, ११; ९८, १^{२}; १०२, ३^{२}; १०५, ११; ११९, ९; १०; १२१, ९; १२९, ७^{२}; १३२, ३; ५; १४८, ३; १५४, ३; १६१, १; २.

वाः १. १३२, ८; २. ४, ६; ४. १९, ४; ८. ९१, १; ९८, ८; ९. ११२, ४; १०. ९३, ३.

वाःऽईव ४. ५, ८; १०. १४५, ६.

वाक् १. १६४, ४५; १६७, ३; १७३, ३; ८. १००, १०; ११; ९. ९७, २२; १०. ११४, ८; ११५, ८; १८९, ३.

वाकं १. १६४, २४^{२}.

वाकस्यं ८. ६३, ४.

वाकेन १. १६४, २४.

वाघत् ९. १०३, ५.

वाघतः १. ३, ५; ५८, ७; ८८, ६; ११०, ४; ३. २, १; ३७, २; ६. १६, १३; ७. ३२, १; ८. ७८, ४; १०. ६२, ७.

वाघतः ३. ६०, ४.

वाघता ३. ३, ४; ८; १०. ३३, ४.

वाघते १. ३१, १४; ४०, ४; ४. २, १३.

वाघत्ऽभिः १. ३६, १३; ३. ८, १०; ८. ५, १६; ९. १०३, ५.

वाचः १. ७९, १०; १९०, २; ५. ७६, १; ७. १०१, १; ९. ३३, ४; ५०, २; ६२, २६; ८५, ७; ९७, ३४; १०. ९१, १२; १६६, ३.

वाचः १. ११३, १७; १४३, १; १६४, ३४; ३५; ३७; ४५; २. २१, ६; ८. ५९, ६; ९. ७, ३; २६, ४; ६२, २५; ६७, १३; ८६, १२; ९६, ७; १०१, ५; १०६, १०; १०. ५३, ४; ७१, १; ३; ८१, ७; ८७, १३; १३७, ७.

वाचं १. ४०, ६; ५३, १; ९२, ९; ११२, २४; १२९, १; १३०, ६; ९; १६४, १०; १६८, ८; २. ४२, १; ३. ८, ५; ३४, २; ४. २१, ५; ३३, १; ५७, ५; ५. ३६, ४; ४३, ११; ५४, १; ६३, ६; ६. २१, ११; ४७, ३; ६७, १०; ७. २२, ३; ३४, ९; १०३, १; ४; ५; ६; ८; ८. ५, ३; ७६, १२; ९६, १२; १००, ११; १०१, १६; ९. १२, ६; ३०, १; ६४, ९; २५; २६; ६८, ८; ७२, १; ७३, ३; ७; ७८, १; ८४, ४; ८६, ३३; ९५, ५; ९७, १३; ३२; ३६; १०६, १२; १०७, २१; ११३, ६; १०. १८, १४; ३४, ५; ४२, १; ६६, १४; ७१, २; ४; ५; ९; ९४, १; ५; १४; ९८, २; ३; ७; ११४, ९; १३०, ४; १७७, २; १८७, १.

वाचंऽईङ्खयः ९. १०१, ६.

वाचंऽईङ्खयं ९. ३५, ५.

वाचंऽवाचं १. १८२, ४.

वाचा १. १२०, ५; ८. ९, १६; २३, ७; ७५, ६; १०. १२, २; २३, ५; ४२, १; ७६, ६; ७७, १; ८७, ४; ९५, २; ११४, ७.

वाचाऽस्तेनं १०. ८७, १५.

वाचि १०. ७१, २; ६; ११०, ११.

वाचि ७. ५८, ६.

वाचौ २. ४३, १.

वाजः १. २७, ८; १११, ५; १६१, ६; २. १, १२; ४. ३३, ३; ९; ३४, १; ३६, ६; ५. १५, ५; ४२, ५; ६. १३, १; ५०, १२; ७. ३७, ४; ४८, २; ३; ८. ८१, ८; १०. १२, ५; २३, २; ३५, १३; ६४, १०; ९३, ७.

वाजऽकृत्येषु १०. ५०, २.

वाजंऽआंध्यं ९. ९८, १२.

वाजंऽजठरः ५. १९, ४.

वाजऽदा १. १३५, ५.
वाजऽदाः ३. २६, ५.
वाजऽदावा ८. २, ३४.
वाजऽदाव्नां १. १७, ४.
वाजंऽद्रविणसः ८. ८४, ६.
वाजंऽपतिः ४. १५, ३.
वाजंऽपत्नी ७. ७६, ६.
वाजंऽपस्त्यः ६. ५८, २.
वाजंऽपस्त्यं ९. ९८, १२.
वाजंऽपेशसं २. ३४, ६.
वाजंऽप्रमहः १. १२१, १५.
वाजंऽप्रसूता १. ९२, ८.
वाजंऽप्रसूताः १. ७७, ४.
वाजऽबंधवः ८. ६८, १९.
वाजंभर्मऽभिः ८. १९, ३०.
वाजे १. ५, ९; २७, ९; ४८, ११; १२; ५२, १; ६३, ९; ६४, १३; ७३, ५; ७७, ५; १००, १९; १०१, ११; १०२, ११; ११०, ६; ११७, १०; ११; १२२, १२; १२३, २; १२४, १३; १२९, २; १८०, ६; २. २, ७; ४, ८; ६, ५; ११, १६; १२, १५; २४, ९; २६, ३; ३१, ७; ३. २, ३; ४; १५, ५; २२, १; २५, २; २९, ९; ४९, ४; ४. ५, १३; १६, ८; ११; १६; १७, ८; ९; ३६, ८; ९; ५. ४, १; ३९, ३; ४४, १०; ५४, १४; ८४, २; ८५, २; ६. ५, ७; ८, ६; १३, ३; १७, १५; २१, १२; २४, २; ३३, २; ४६, २; ५४, ५; ६०, १; ६५, ३; ७०, ५; ६; ७. ५, ९; १९, ६; २५, ५; २७, ४; ३२, ११; १४; २०; ३६, ८; ४२, ६; ५६, २३; ९३, १; ८. १, ४; २, २४; ३३, ३; ६०, १८; ६१, ४; ८८, २; ९५, ९; १०३, ५; ११; ९. १, ४; ६, ३; २०, २; २३, ६; ३३, २; ३५, ४; ३८, १; ४४, ६; ५१, ५; ५२, १; ५६, २; ५७, १; ६१, २०; ६३, १२; १४; १८; ६४, २९; ६७, ४; ६८, ७; ७०, १०; ८२, २; ५; ८३, ५; ८६, ३; ४०; ८७, १; ६; ९०, १; ९६, ८; १६; १०८, २; ११०, ४; १०. ११, ५; ४७, ५; ६१, ९; ६२, ११; ६७, १०; ६९, ३; ७५, ९; ९६, १०; ९९, ३; १०६, ११; १४०, १; १४७, ४; १४८, १.
वाजंऽइव ९. ३७, ५; ६२, १६.
वाजंऽभरः ४. ११, ४.
वाजंऽभरं १. ६०, ५; १०. ८०, १.
वाजयं १०. ६८, २.
वाजऽयतः १. १३०, ५.
वाजऽयतां ६. ४५, २९.
वाजयते ४. ७, ११.
वाजयत्ऽभिः ५. ६०, १.
वाजयध्यै ४. २९, ३.
वाजयन् १. १०६, ४; ३. ६०, ७; ७. २४, ५; ३२, ११; ९. ६८, ४; १०. ९७, ११.
वाजयन्ऽइव २. ८, १.
वाजयंतः २. १९, ७; ३८, १०; ४. १७, १६; ४२, ५; ६. ५, ७; २२, २; २४, ६; ७५, ७; १०. १६०, ५.
वाजऽयंतः १. ३०, १; १३२, १; ३. ६२, ११; ४. २५, ८; ५. ४, १; ६. १९, ४; ७. ९०, ७; ८. ३, १५; ११, ९; ५३, २; ७४, १; १००, ३; ९. ६७, १७.
वाजऽयंतं ५. ३१, १; ३५, ७; ८. ९८, १२.
वाजयंता २. ११, ७.
वाजऽयंता ६. ६०, १.
वाजऽयंतीं ५. १, ३.
वाजयंती इति ३. १४, ३.
वाजऽयंतीः ४. ४१, ८.
वाजऽयंतीः १. १०९, १; ३. ६२, ८.
वाजयामः १. ४, ९.
वाजयामसि ८. ४३, २५; ९३, ७.
वाजऽयु ८. ८०, ५.
वाजऽयुः २. २०, १; ३५, १; ५. १०, ५; १९, ३; ७. ३१, ३; ८. ५३, ८; ९. ४४, ४; ८३, ३; ९६, १४; १०३, ६; १०६, १२; १०७, ११.
वाजऽयुं २. ३१, २; ८. १, १९; ८०, ६; ९. ६३, १९.
वाजऽरत्ना ४. ४३, ७.
वाजंऽरत्नाः ५. ४९, ४; ६. ३५, १.
वाजऽरत्नाः ४. ३४, २; ३५, ५.
वाजंऽरत्नां १०. ४२, ७.
वाजंऽवत् १. ९, ७; ९. ४१, ४; ४२, ६; ८६, १८.
वाजंऽवतः ६. ५०, ११.
वाजंऽवतीः १. ३४, ३; ६. ६०, १२.
वाजंवत्ऽभिः ३. ६०, ५.
वाजंऽवत्या १. ३१, १८.
वाजंऽवत्यै १. १२०, ९.
वाजंऽवंतं ३. ५२, ६; ४. ३४, १०.
वाजंऽवंता ८. ३५, १५.
वाजंऽवान् ३. ६०, ६.
वाजंऽश्रवसः ६. ३५, ४.
वाजंऽश्रवसं ३. २, ५.
वाजंऽश्रुतासः ४. ३६, ५.
वाजऽसनिः ९. ११०, ११.
वाजऽसनिं ३. ५१, २; १०. ९१, १५.
वाजऽसाः ९. २, १०; ३५, ४.
वाजऽसातम ५. २०, १.
वाजऽसातमः ९. ६६, २७; १००, ६.
वाजऽसातमं १. ७८, ३; ५. १३, ५; ९. ९८, १; १०. १७०, २.
वाजऽसातमा १. २८, ७; ३. १२, ४; ८. ५, ५.
वाजंऽसातये १. १३०, १[२]; २. ३१, ३; ३. २, ७; ३७, ५; ५. ३५, ६; ४६, ७; ६४, ६; ६. ५३, १; ४; ५७, १; ७. ९४, ५; ८. ४, १८; ६, ३७; ८, २१; ९, १३; १३, ३; २७, १३; ३४, ४; ४०, २; ७४, १२; ८०, २; ८७, ६; ८८, ६; १०२, ३; ९. १३, ३; ४; ६; ४२, ३; ४३, ६; १०७, २३; ११०, १; १०. २१, ४; ६६, ७; १०१, १२.
वाजंसातिऽभिः ८. २०, १६.
वाजंऽसातौ १. ३४, १२; ११०, ९; ११२, २४; ३. ३०, २२; ४. १६, १८; २०, २; ४१, ११; ५.

३३, १; ७; ६. १५, १५; ६६, ८; ७. ३५, १; ४८, २; ९. ९७, १९; १०. ३५, १४.

वाजऽसां ६. ५३, १०.

वाजऽसृत् ९. ४३, ५.

वाजस्य १. ११, ३; ३६, १२; १३; ७९, ४; ९१, १६; १४५, १; २. १, १०; ३. १६, ६; ४. १२, ३; ३२, ७; ५. ९, ७; २३, २; ४३, ९; ६. १०, ६; २६, १; २; ३७, ५; ४५, २३; ४६, १; ६०, १३; ७. २१, ७; ६०, ११; ९३, २; ८. २५, २०; ४५, २८; ७५, ४; ९६, २०; ९. ७, ९; ८६, १२; १०. २३, ३; ९३, १०.

वाजा ६. ४८, ४.

वाजाऽइव १०. १०६, ५.

वाजाः १. ९१, १८; १६७, १; ३. १४, ६; २६, ४; २७, १; ३०, २१; ५. २५, ७; ७. १, ३; ८. ८१, ९; ९. ६९, ७; १०. ३१, ५; ७३, ३; १४२, ६.

वाजाः ४. ३४, ३–५; ३५, ३; ३६, २–४; ७; ३७, १; ३; ७; ८; ७. ३७, १; ४८, १.

वाजान् १. ९२, ७; १११, ४; १२१, १४; १७४, ४; २. १७, ८; ३. १५, ६; ३०, ११; ४. ३, १५; ४, १४; २२, १०; ५. ४१, १; ६५, ३; ६. १७, २; २४, ९; ४५, १२; ५०, ६; ७. १९, ११; २३, ४; २६, ५; ८१, ६; ९३, ८; ९५, ६; ८. २, ३१; २६, २५; ९. ५४, ४; ६७, ५; ७६, ३; ९०, ४; ९१, ४; ९९, २; ११०, २; १०. २५, ११; २८, १२; ५३, ८; ६१, २७; ७५, २.

वाजानां १. ११, १; ६. ३६, १; ८. २४, १८; ९२, ३; ९. ३१, २; १०. २६, ७; ९.

वाजानां १. २९, २; ६. ४५, १०; ८. ९२, ३०.

वाजाय १. २७, ११; १२१, २; १८०, २; ३. १०, ६; १९, १; ४. २१, ८; ३२, ६; ९; ५. १०, १; ४३, २; ६. १७, १४; ८. ३, ११; ९. ३, ३; ६२, १८; ७७, ३; ८६, ३४; ८७, ५; ११०, ७; १०. ५, ४; ५०, ३; ९६, ९.

वाजासः ४. ८, ७; ५. ९, २.

वाजासः ४. ३५, ६.

वाजिन् ९. ६६, १०.

वाजिन् १. १६३, ५; ८. ५२, ४; ९. ८०, २; १०. ५६, २.

वाजिनः १. ११, २; २३, १९; २४, ९; ८६, ३; ११७, ६; १६२, १; ८; १८; २. २, ११; ५, १; २४, १०; ३. २७, ३; ५३, ५; ४. ६, ५; ३९, ६; ५. ६, १; ७; ६. १३, ६; ४७, २२; ७५, ६; ७. ३२, २३; ३६, ७; ३८, ७; ४१, ६; ५६, १५; ९३, ३; ८. ३, २; ४, २०; २०, १६; ९. ६, २; १४, ७; २१, ७; २२, १; ६२, २; ६४, ४; ६५, ९; १०. ६४, ६; ६६, १०.

वाजिनः ४. ३७, ४; ७. ३८, ८.

वाजिनं १. ४, ८; ९; ६४, ६; १०६, ४; ११७, ९; १२९, १; २[2]; १३०, ६; १३५, ५; १६२, १२; १७६, ५; २. १३, ५; ३२, ३; ३४, ७; ३. २, १४; ४. ३८, २; ५. १, ७; ६, ३; ६. ५५, ४; ७. ७, १; ९५, ३; ८. २, ३८; १६, ३; २४, २२; ४३, २०; २५; ४६, १५; ६१, १२; ८४, ८; ९३, ३४; ९. ६, ५; १७, ७; २६, १; ५३, ४; ६२, १८; ६३, १७; ६५, ११; ८७, १; ८९, ४; १०६, ११; १०. ३९, १०; ८७, १; १२२, ४; ८; १४१, ५; १४३, २; १४७, ३; १७८, १; १८८, १.

वाजिना ३. २०, २.

वाजिना १. १६२, ३; २. २४, १२; ३. ५३, २३; ६. १६, ४८; ६७, ४; ७. १०४, ६; १०. ९३, ८.

वाजिना ८. ३५, २.

वाजिनानि १०. १०३, १०.

वाजिनां १०. १०३, १०.

वाजिनाय १०. ७१, १०.

वाजिनि ३. ६१, १; ६. ६१, ६.

वाजिनिऽइव ९. ९४, १.

वाजिनीं ३. ६, १.

वाजिनीऽवति १. ४८, ६; १६; ९२, १३; १५; २. ४१, १८; ४. ५५, ९; ६. ६१, ३; ८. २४, २८.

वाजिनीऽवती १. ३, १०; ६. ६१, ४; ७. ७५, ५; ९६, ३; १०. ७५, ८.

वाजिनीऽवतोः १. १२०, १०.

वाजिनीऽवसुः १०. ९६, ८.

वाजिनीवसू इति वाजिनीऽवसू १. २, ५; २. ३७, ५; ५. ७४, ६; ७; ७५, ३; ७८, ३; ८. ५, ३; १२; २०; ८, १०; ९, ४; १०, ५; २२, ७; १४; १८; २६, ३; ८५, ३; १०१, ८; १०. ४०, १२.

वाजिनीवसो इति वाजिनीऽवसो ३. ४२, ५.

वाजिनीऽवान् १. १२२, ८; ५. ३६, ६; ७. ६९, १.

वाजिनेन १०. ५६, ३.

वाजिनेयः ६. २६, २.

वाजिनेषु १०. ७१, ५.

वाजिनौ ५. ३६, ६; ८. २५, २४.

वाजिन्ऽतमं ४. ३७, ५.

वाजिन्ऽतमाय १०. ११५, ६.

वाजिऽभिः ३. ३०, १८; ६०, ७; ६. १६, ४; ९. ६४, १५.

वाजी १. ६६, २; ६९, ३; ७४, ८; ११६, ६; १३३, ७; १६२, २१; २२; १६३, १२; १७५, १; २. १०, १; २४, १३; ४३, २; ३. २७, ८; २९, ६; ७; ३८, १; ६. ३, १२; ११, ४; १५, १; ३६, ६; ३८, ७; १०; ४०, ४; ५८, ७; ५. १, ४; ३०, १४; ५६, ७; ४. २, २; ८; ७, ३; २४, २; २६, २; ७. १, १४; ४, ८; ३२, १४; ३४, १; ३७, ६; ४४, ४; ७०, १; ९०, २; ८. ३२, १८; ९३, ३४; ९. ७, ४; १५, ५; २८, १; ३६,

१; ३७, ३; ४५, ४; ६४, २९; ७४, १; ८; ८६, ११; ८७, ४; ९३, १; ९६, ९; १५; ९७, १०; ४५; १०७, ५; १०९, ६; १०; १७; १९; **१०.** ३१, ११; ३४, ४; ५६, ३; १०३, ५.

वाजीऽइव ९. १००, ४.

वाजे **१.** ३०, ६; ४२, ८; ८५, ५; **४.** ३७, ५; **५.** ४, ६; **७.** ६७, ५; **८.** २१, १; ८; ५२, ४; ५४, ६; **९.** ६३, १९; **१०.** ६, ६; ८१, ७; १४९, ५.

वाजेन **३.** ६१, १.

वाजेभिः **१.** ३, १०; ५, ३; ३०, ८; २२; ५३, ५; ११०, ७; ९; १४७, १; **४.** २२, ३; २९, १; **६.** ३२, ४; ४५, २१; २९; ६१, ४; **७.** ५७, ५; **८.** २, १९; १६, १२; १९, १८; ४६, ११; १०३, ९; **९.** १८, ६.

वाजेऽवाजे **१.** ३०, ७; १३८, ३; **६.** ६१, १२; **७.** ३८, ८.

वाजेषु **१.** ४, ८; ९; ७, ४; १०, १०; २७, ५; ७; ३६, २; ६३, ६; ८१, १; १२९, ४; १३०, ६; १३८, २; १७६, ५; **२.** २३, १३; **३.** ११, ९; १२, ९; २७, ८; ३७, ६; ४२, ६; **५.** २३, १; ३५, १; ८६, १; २; **६.** १४, ५; ४८, २; ६१, ६; **८.** ५, २६; ११, ९; २२, २; ३१, ६; ३८, १; ४६, ९; १३; १५; २०; ६०, १०; ६८, १०; ७०, ८; **९.** ४७, ५; ६५, ११; १२.

वाजैः **१.** ४८, १६; ११६, १९; ११७, १; १६९, ४; १७३, ७; १८१, ५; ६; **३.** २५, ३; २७, ११; **६.** १, ११; २५, १; **७.** ९३, ६; **८.** १०२, ९; **१०.** ३९, १०.

वांछंतु **१०.** १७३, १.

वाणः **८.** २०, ८.

वाणं **१.** ८५, १०; **४.** २४, ९; **९.** ९७, ८.

वाणस्य ९. ५०, १; **१०.** ३२, ४.

वाणीं **१.** ८८, ६; **६.** ६३, ६; **७.** ३१, ८.

वाणी इर्ति **१.** ११९, ५.

वाणीः **१.** ७, १; १६४, २४; **३.** १, ६; ७, १; ३०, १०; **६.** ३४, ३; **७.** ३१, १२; **८.** ९, १९; १२, २२; ५९, ३; **९.** ९०, २; १०३, ३; १०४, ४; **१०.** १२३, ३.

वाणीःऽइव ५. ८६, १.

वाणीची ५. ७५, ४.

वाणीभिः **८.** ९, ९.

वाणी २. ११, ८.

वाणीषु ९. ८२, ४.

वात **१०.** १३७, ३[२]; १८६, २; ३.

वातऽउपधूतः **१०.** ९१, ७.

वातः **१.** २८, ६; २९, ६; ३४, ७; ८९, ४; ११६, १; १२२, ३; १४८, ४; १६१, १४; १८०, ६; १८६, १०; **२.** ३८, २; **४.** ७, १०; १७, १२; १९, ४; **५.** ४१, ४; ४६, ४; ७८, ७; ८; **७.** ३५, ४; ४०, ६; ८७, २; **८.** १८, ९; ५४, ४; **९.** ९७, ५२; **१०.** २३, ४; ३१, ९; ६०, ११; ६८, ५[२]; १०२, २; १२८, २; १५८, १; १६९, १; १८६, १.

वातः **१०.** १३७, २.

वातःऽइव **१.** ७९, १; १६३, ११; **१०.** ९५, २; १२५, ८.

वातऽचोदितः **१.** ५८, ५; १४१, ७.

वातऽजूतः **१.** ५८, ४; ६५, ४; **१०.** १७०, १.

वातऽजूता **१.** ९४, १०.

वातऽजूताः **१.** १४०, ४; **४.** ३३, १; **८.** ४३, ४.

वातऽजूतासः **६.** ६, ३.

वातऽत्विषः ५. ५४, ३; ५७, ४.

वातऽप्रमियः **४.** ५८, ७.

वातं २. १४, ३; **१०.** १६, ३; ६४, ३; ९२, १३; १४१, ५.

वातंऽइव **४.** ३८, ३.

वातय **१०.** २५, १.

वातयामसि **१.** १२८, २.

वातंऽरंहसः **१.** १८१, २; **८.** ३४, १७.

वातंऽरंहाः **१.** ११८, १; **५.** ७७, ३.

वातऽरशनाः **१०.** १३६, २.

वातस्य **१.** २४, ६; २५, ९; ५१, १०; १२१, १२; १७४, ५; १७५, ४; **३.** १४, ३; २९, ११; **४.** ७, ११; १६, ११; **५.** ५, ७; ३१, १०; ४१, ३; **७.** ३६, ३; **८.** १, ११; ५०, ८; **१०.** २२, ४; ५; ८९, ११; ९७, १३; १३६, २; ५; १६८, १; २.

वातस्यऽइव **७.** ३३, ८.

वातऽस्वनं **८.** १०२, ५.

वातऽस्वनसः **७.** ५६, ४.

वाताऽइव २. ३९, ५.

वाताः **१.** ९०, ६; **४.** २२, ४; **५.** ८३, ४; ९. ३१, ३; **१०.** ११५, ४.

वाताःऽइव **१.** १८७, ४; **८.** ४९, ८; **९.** २२, २; **१०.** ११९, २.

वातान् **१.** ६४, ५; **४.** २७, २; **५.** ५८, ७; **१०.** १३६, ३.

वातापर्जन्या **१०.** ६६, १०.

वातापे **१.** १८७, ८–१०.

वाताप्यं **१.** १२१, ८; ९. ९३, ५; **१०.** २६, २.

वाताप्याय **१०.** १०५, १.

वाताय **४.** ३, ६; **१०.** १६८, ४.

वातासः **१०.** ७८, २; ३.

वाति **१.** २८, ६; ५८, ५; १४८, ४; **४.** ४०, ३; **१०.** ३१, ९; ६०, ११.

वातु **१.** ८९, ४; **७.** ३५, ४; **८.** १८, ९; **१०.** १३७, २[२]; १६९, १; १८६, १.

वाते **८.** ४०, १.

वातैः **२.** १, ६.

वातौ **१०.** १३७, २.

वाधूऽयं **१०.** ८५, ३४.

वाध्रिऽअश्व **१०.** ६९, ५; ९; १२.

वाध्रिऽअश्वस्य **१०.** ६९, ५.

वांति ५. ८३, ४.

वापय **१०.** १६, १३.

वापुषः ५. ७५, ४.

वां **६.** ५५, १.

वां **१.** २, ४; १७, ३; ७–९; २२, ३; ४; ३०, १८; ३४, १; ५; १२;

४६, १; ३^{२}; ५; ८; ४७, १; २; ४; ८; ९३, २–४; १०^{२}; १०८, १; ५; ६; १०९, १; २; ११२, २४; ११६, ६; ११; १२^{२}; १३; १७; १८; २५; ११७, १; २; ४; ६; ८; १०^{२}; १५; १६; १९; २२^{२}; २३; २५; ११८, १; ३; ४; ५^{२}; १०; ११; ११९, १; २; ४; ५; ७; ९^{२}; १२०, १^{२}; ३; ५; ६; १२२, ७; ९; १५; १३५, ४^{२}; ५; ६^{२}; १३७, १; २; ३^{२}; १३९, ४^{२}; ५; १५१, २; ३; ६–९; १५२, ३; ७; १५३, १^{२}; २^{३}; ३; ४; १५४, ६; १५५, २; १५७, ६; १५८, १; २; ३^{२}; ४; १८०, १^{२}; २–४; ५^{३}; ७; १०; १८१, १–७; ८^{२}; ९; १८२, ८^{२}; १८३, ३; ४^{३}; ६; १८४, १; ३; ४^{२}; ५; ६; १८५, ११; **२.** २४, १२; ३१, ५; ३२, १; ३७, ५; ३९, ८; ४१, ४; २१; **३.** ४, ४; १२, ५; ८; ९; ३३, २; ५४, ४^{२}; ५८, २–४; ५^{२}; ८^{२}; ६२, १^{२}; २; **४.** १४, ४^{२}; १५, ९; १६, १०; ३८, १; ४१, १^{२}; ८; ११; ४२, ९; ४३, ४^{२}; ५^{४}; ६^{२}; ७; ४४, २; ३; ५^{२}; ६; ४५, २; ४; ७; ४६, ३; ७^{२}; ४७, ४; ४९, १; २; ५०, १०; ११; ५६, ५; **५.** ३१, ८; ९; ४१, १; ३; ४९, १; ६२, १; २^{२}; ४; ६३, २; ४; ६४, २; ६५, ३; ६६, ३; ६; ६७, ५^{२}; ६८, ३; ६९, २^{२}; ४; ७०, १^{२}; २; ७३, ४^{२}; ५^{२}; ६; ७^{२}; ८; ७४, १–३; ६^{२}; ७–९; १०^{२}; ७५, १; ४^{२}; ६; ९; ७६, ४; ७७, ३; ७८, ४; **६.** ५९, १^{२}; २^{२}; ४; ५; ६०, १३^{२}; ६३, ३; ४; ६^{२}; ७^{२}; ८^{२}; १०; ११; ६७, २^{२}; ५; ८^{२}; ९–११; ६८, १; ५; ११; ६९; १–३; ५; ७; ७०, ३; ७२, १; ३; ७४, १; **७.** २, ७; ३६, २^{२}; ५३, २; ३; ६०, ४; ६१, १; २; ५^{२}; ६^{३}; ६२, ४; ६३, ५; ६४, १; ४; ६५, २–४; ६७, १^{२}; ३; ४^{३}; ६; ७; ८^{२}; ६८, २–४; ५^{२}; ६; ६९, १; ३–५; ६^{२}; ७०, १; २^{२}; ५; ६; ७१, १; ३; ४^{२}; ७२, १; ४; ७३, २; ३; ७४, १; ४; ८२, २^{२}; ९; ८३, ९; ८४, १^{२}; ८५, १^{२}; ४; ९०, १; ५; ९१, २; ५; ६; ९२, २; ९३, १; ६; ९४, १; ६; ९; ९७, ९; ९९, ६; १०४, ३; ६^{२}; **८.** ५, १६; १८; १९; २२^{२}; २४; २७; २९; ३३; ३४; ८, ४; ६; ८–११; १५; १६; १८; १९; २२; ९, ३; ४; ६; ८; ९; १०^{२}; १४^{२}; १०, ५; २२, ४^{२}; ५; ६; ८; १८; २५, १; ६; २६, ३; ४; ९; १३; १४; १६; १८; ३५, २२; ३८, ३; ९; ४०, २; ४२, ४; ५; ६; ५७, ३; ४; ५८, ३; ५९, १^{२}; ३^{२}; ४; ७३, १; ११–१३; ८५, ३; ८६, १; २; ८७, १; १०१, ३; ८; **९.** ९८, ९; **१०.** १२, ४; १३, १; २; २२, ६; २९, १; ३९, १^{२}; ४; ५^{२}; ६; १२; १४; ४०, १; २; ५; १२; ५२, २^{२}; ६१, ४; ७०, ६; ७९, ४; ८५, १४; १५; १३२, २; ३; १४३, ३; ४; ६; १६७, ४; १७८, २.

वामऽजाताः १०. १४०, ३.

वामऽदेवस्य ४. १६, १८.

वामऽनीतिः ६. ४७, ७.

वामऽभाजः ३. ५५, २२; ६. ७१, ६.

वामं १. २३, ३; १२४, १२; १४१, १२; १९०, ५; ३. ६१, ६; ४. ५, १३; ३०, २४^{३}; ५. ६०, ७; ६. १९, १०; ५३, २; ७१, ४; ६^{३}; ७. २७, ४; ७१, २; ७८, १; ८. २७, २१; ८३, ४^{३}; १०. ७, ४; ४०, १०; ४२, ८; ५६, २; ६३, १६; १२२, १; १२४, ६; १८०, ३.

वामंऽवामं ४. ३०, २४; १०. ७६, ८.

वामया ८. ९, ७.

वामस्य १. १६४, १; ७; २. ३८, १०; ६. १३, २; १९, ५; ४८, २०; ७१, ६; ८. १, ३१; २७, ११; ८३, ५; १०. १४०, ५.

वामा १. ४०, ६; ६. १, ९; ७. १८, १.

वामानि ५. ८२, ६; ८. २२, १८; १०३, ५.

वामि १०. १२५, ८.

वामी ६. ४८, २०; १०. ६९, १.

वामीः ३. ५३, १.

वामे १०. २०, ८.

वामेनं १. ४८, १.

वायतः ८. ३१, ६.

वायतस्य ७. ३३, २.

वायति ८. ४३, ७; ४७, ६.

वायंति ७. ६७, ८.

वायवः २. ११, १४; १०. ४६, ७.

वायवे १. १४२, १२; २. ११, ३; ५. ४३, ३; ५१, ४; ७; ७. ६४, ५; ९१, १; ३; ९२, २; ४; ९. २५, १; २७, २; ३३, ३; ३४, २; ४४, ५; ६१, ९; ६३, ३; १०; ६५, २०; ७०, ८; ८४, १; ८५, ६; १०८, १६; १०. १००, २.

वायुभ्यान् १०. ९०, ८.

वायसं १. १६४, ५२.

वायुः १. १३४, ३^{३}; ३. ३५, १; ४९, ४; ६. ४, ५; ५०, १२; ७. ५, ७; २३, ४; ३५, ९; ३९, २; ४०, २; ९. ५, ११; ८१, ४; ८८, ३; १०. ६५, १; ६६, ५; ८५, ५; ९०, १३; ९२, १३; १०६, ७; १३६, ७.

वायुऽकेशान् ३. ३८, ६.

वायुऽगोपाः १०. १५१, ४.

वायुना १. १४, १०; ३. ५८, ७; ४. २१, ४; ५. १९, ५; ५१, १०; ८. ९, १२; ९. ६१, ८.

वायुऽभिः ८. ७, ३; ४; १७; ९. ८४, ४.

वायुं ५. ४१, ६; ५१, १२; ६. ४, ७; ४९, ४; ७. ९०, ३; ८. २६, २२; ९. ७, ७; ८, २; २५, २; ४६, २; ६३, २२; ६७, १८; ९६, १६; ९७, ४२; ४९; १०. ६५, १०; १०७, ४.

वायून् ९. ९७, १७.

वायो इति १. २, १–३; ५; ६; २३, १; १३४, १²; १३५, ३²; ४²; ६; २. ४१, १; ४. ४६, २; ४७, १; ३; ४८, १; ५; ५. ५१, ५; ७. ९२, ५; ८. २६, २३; २५; १०१, ९.

वायो इति १. १३४, २; ६; १३५, २; ७–९; २. ४१, २; ४. ४६, १; ४७, २; ७. ९०, १; २; ९२, १; ३; ८. २६, २०; २१; ४६, २५; २८; ३२.

वायोः १. १६९, ४; ५. ४३, ९; ६. ३७, ३; ७. ६२, ४; ८. १०२, १३; ९. १३, १; ८६, २०; ९७, २५; १०. ७६, ५; १३६, ५.

वायोःऽइव १. ११३, १८; ६. ४५, ३२.

वाय्ये ५. ७९, १.

वारः १. ३२, १२.

वारणः १. १४०, २; ८. ३३, ८; ६६, ८.

वारणं ६. ४, ५; ९. १, ८.

वारणा १०. ४०, ४.

वारणेषु १०. १८५, २.

वारे १. १२८, ६; १३२, ३; १५१, ५, ५. १६, २; ९. १३, ६; १६, ८; २८, १; ३७, ३; ३८, ५; ६०, २; ६१, १७; ६७, २०; ६९, २; ४; ७४, ९; ८२, १; ८५, ५; ८६, २६; ३१; ९७, ४; ५६; १००, ४; १०६, १०; १०९, १६; ११०, ६.

वारयंते ४. १७, १९; ८. ८१, ३.

वारयंते १०. २७, ५.

वारऽवंतं १. २७, १.

वाराणि ९. ६७, ४; ८८, ६; ९६, २१; १०३, २; १०७, १०.

वारान् २. ४, ४; ९. ६०, ३; ९७, ३१.

वारितिऽवाः १. ११६, २२; १०. १२, ३; ९९, ४; १०५, १.

वारे ९. ७, ६; १२, ४; ३६, ४; ५०, ३; ५२, २; ६४, ५; ६६, ११; ८६, २५; ४८; ९९, ५; १०३, ३; १०७, ६; २२; ११०, १०.

वारेण ९. १, ६; ९८, ७.

वारेभिः ९. २०, १; ३८, १; ६८, ७; १०१, १६; १०८, ५; १०. ७४, २.

वारेषु ९. ६, १; ६३, १०; १९.

वारैः ८. २, २.

वार्कार्यां १. ८८, ४.

वार्त्रऽहत्याय ३. ३७, १.

वार्यं १. २६, ८; ८१, ९; १२९, १०; ३. ८, ७; २१, २; ४. ५३, १; ५. ६, ३; ६; १६, ५; १७, ५; ३५, ८; ४१, १३; ४८, ५; ६. १५, ६; ७. १५, ११; १२; १६, ५; ४२, ४; ८. २२, १८; २५, १३; ४३, ३३; ९. ३५, ३; १०. १७, ७; २४, २; ६४, १५; १३३, २.

वार्यस्य ७. २४, ६; ८. ४४, १८.

वार्या १. ५८, ३; ३. ११, ९; ४. ५५, ९; ५. २३, ३; ६. १६, ५; ८. १, २२; २३, २७; ६०, १४; ७५, २; ९. ३, ४; १८, ४; २१, ४; ४२, ५; ६३, ३०; ६६, ४.

वार्याणां १. ५, २; २४, ३; ६. ५, ३; ८. ७१, ११; १३; १०. ९, ५; २४, ३.

वार्याणि १. ३५, ८; ११३, १५; ११४, ५; १४९, ५; १५९, १; १६३, १३; १६४, ४९; ३. ५६, ६; ५. ४, ३; ४९, ३; ८०, ६; ६. ५०, ८; ७. २, ७; १७, ५; ८. १९, २४; ९. ९०, २; १०. ४५, ११.

वार्येण १०. २७, १२.

वार्षागिराः १. १००, १७.

वावक्रे ७. २१, ३.

वावदत् ६. ५९, ६.

वावदतः १०. ६८, १.

वावदत्ऽभिः १०. ६७, ३.

वावदीति ६. ४७, ३१.

वावशतीः ४. ५०, ५.

वावशंत १. ६२, ३; ७. ७५, ७.

वावशानः २. ११, ८; ३. २२, १; ३५, ९; ५१, ८; ६. ३२, २; ९. ९३, २; ४; ९६, १४; १०. ५, ५.

वावशानं ९. ९५, ४.

वावशाना १. ११३, १०; १६४, २८.

वावशानाः १. ७३, ६; ३. २०, १; ५७, ३; ४. २६, २; ७. ५, ५; ३६, ६; ५६, १०; ९. ८६, ३१; ९७, २२; ३४; ३५; १०. १२३, ३.

वावशाने इति १०. ८९, १३.

वावशुः ६. ५१, १४; ८. ३, १८.

वावशे २. १४, ९.

वावश्रे ९. ९४, २.

वावहिः ९. ९, ६.

वाशः ८. १९, ३१.

वाशति ५. ५४, २.

वाशीऽइव ८. १२, १२.

वाशीः १. ८८, ३.

वाशीभिः १. ३७, २; १०. ५३, १०; १०१, १०.

वाशी ८. १९, २३; २९, ३.

वाशीऽमंतः १. ८७, ६; ५. ५७, २.

वाशीऽमंतं १०. २०, ६.

वाशीषु ५. ५३, ४.

वाश्रः ९. ३४, ६.

वाश्रं १०. ९९, १.

वाश्रा १०. ११९, ४.

वाश्राऽइव १. ३८, ८; २. ३४, १५; १०. १४९, ४.

वाश्राः १. ३७, १०; ९५, ६; ८. ७, ७; ९. १३, ७; ७७, १; १०. ७५, ४.

वाश्राःऽइव १. ३२, २.

वाश्राय ८. ४३, १७.

वाश्रासः ८. ७, ३; ४४, २५.

वासः १. ११५, ४; १६२, १६; ७. ७७, २; ८. ३, २४; ९. ८९, २; १०. ८५, ६; ९७, ४; १०२, २.

वासःऽदाः १०. १०७, २.

वासःऽवायः १०. २६, ६.

वासते १०. ३७, ३.

वासय १. १३४, ३²; १४०, १; ९. ७५, ५.

वासयः ६. ३५, १.

वासयत् ६. ३९, ४.

वासयथः ६. ७२, २.

वासयंतः **८.** १, १७.

वासयंसिऽइव **७.** ३७, ६.

वासयामसि **९.** ८, ५; ३५, ५; ४३, १; १०४, ४.

वासयिष्यसे **९.** २, ४; ६६, १३.

वासरं **८.** ६, ३०.

वासराणि **८.** ४८, ७.

वासरीं **१.** १३७, ३.

वासंसः **१.** ३४, १.

वासंसा **९.** ६९, ५; **१०.** ८५, ३०.

वासांसि **१०.** २६, ६.

वासे **५.** ४३, १४.

वास्तुं **८.** २५, ५.

वास्तूनि **१.** १५४, ६.

वास्तोः **५.** ४१, ८; **७.** ५४, १–३; **८.** १७, १४; **१०.** ६१, ७.

वास्तोः **७.** ५५, १.

वाहः **३.** ३०, २०; ५३, ३; **१०.** २९, ३.

वाहंसा **३.** ११, ७; **८.** ६, २.

वाहाः **४.** ५७, ४.

वाहि **१०.** १३७, ३^{२}.

वाहिष्ठः **६.** ४५, ३०; **७.** ३७, १; **८.** ५, १८; २६, ४; १६.

वाहिष्ठं **५.** २५, ७.

वाहिष्ठा **८.** २६, १८.

वाहें **७.** २४, ५.

वाहैः **४.** ५७, ८.

वि **१.** ३, १२; ७, ३; ११, ३; १२, ४; १३, ६; २२, १; १७; १८; २४, १२; १३; १५; २५, ३; २१; २८, ६; ३२, १०; १३; ३३, ४; १२; १३; ३५, ५; ७; ८; ३६, ३; ९; १६; ३९, ३^{२}; ५; ८^{२}; ४१, ३^{२}; ४२, १; ४६, १; १०; ११; ४८, १; ६^{२}; ७; १०; १५; ५०, ३; ७; ५१, ८–११; ५४, ९; ५५, १; ५६, ५; ६; ५८, ३; ४; ६१, १०; १२; ६२, ५^{२}; ७; ६३, ४; ५; ६४, ४; ६; ६५, ४; ६७, ४; ५; ६८, १; ५; ६९, ३; ५; ७०, ५^{२}; ७१, ७; ७२, ७–९; ७३, १; ५^{२}; ६; ९; ८०, ८; १२; ८१, ६; ८५, ४; ५^{२}; १०; १२; ८६, १०; ८७, १; ८९, ८; ९०, ४; ९१, २२; ९२, ४; ५; ९; ११; १२; १४; ९३, ३; ९४, ११; ९५, ३; ११; ९६, ५; ९; ९८, १; १०१, १०^{२}; १०२, ६; १०३, २; ३; ८; १०५, ४; ८; १५; १०९, १; ११०, ५; ११३, ४^{२}; ७; ९; १२; १३^{३}; १४; १५; १९^{२}; ११६, २०; ११७, १६; १२०, ४; १२१, १५; १२३, २; ११; १३; १२४, २; ५; ११; १२८, ६; १३१, ३; १३२, १; ३; १३५, ७; १३९, ४; ७; १४०, ९; १४१, ५; ७; १४२, ६; १०; १४५, २; ५; १४६, ३; १५०, २; १५२, २; १५७, १; १५८, ३; ४; १६०, ४; १६१, १३; १६२, १८; १६४, ५; ६; १४; १६; ३७; ४२; ४४; ४७; १६६, ९; १०; १२; १६८, ६; १७०, १; १७१, १; १७७, ४; १८०, ७; १८१, ५; १८५, १^{२}; १८७, १; १८९, ६; ७; १९१, १४; **२.** १, १०; १५; २, ७; ३, ५^{२}; ९; ४, ४; ७; ७, ४; ११, ७; १३, ७; १५, ३; ७; ८; १८, ८; १९, २; ६; २०, ७; २३, ५; १३; १४; १६; १८; २४, २^{२}; ३; १४; २६, १; २७, ११; २८, ४–७; ३२, २; ३३, २^{३}; ३४, २; ३५, ७; ३८, १; ३–५; ७; ८; ४०, ४; **३.** १, ८; ९^{२}; १८; २, ११; ४, ४; ९; ७, ४; ८, ११^{२}; १०, ७; १४, ६^{२}; १५, १; ३; १८, २; २३, २; २९, ६; ३०, १०; १६; ३१, १०; १२^{२}; १९; ३३, ७; ३४, १; ३५, ३; ३६, ८; ३९, २; ४१, ८; ४३, १; ५३, १०; १७^{२}; २२^{२}; ५४, ८; ५५, १; ३; ९; १४; ५८, २; ६१, २; ७; **४.** १, १४; १५; १८; २, ९; ११; ३, ११; १४; ४, २; ३; ६; ५, १२; ६, ११; ७, १०; ८, ६; ११, २; १२, ३; ४; ६; १४, २; १६, ५; ६; १०; १३; १४; १७, ७; १८, ६; ७; ११; १९, ३; ८; ९; २०, ५; २१, ८; २४, ३; ५; ८; ९; २५, ७; २६, ३; २७, ३; ३०, २०; ३५, ३^{२}; ३६, ४; ३७, ७; ३९, ५; ४२, ४; ४५, १; ५०, १; ४; ५१, २; ६; ५२, ६; ५४, १; २; ५५, २^{२}; ४; ५७, ८; **५.** २, ५; ७; ९; ५, ४; ५; ८, ५; ७; ११, १; ४; १३, ४; १५, ३; १६, २; १८, ३; १९, १; २; २८, १; २९, ४; ३०, ४; ७; ३१, १–३; ३२, १^{३}; ३४, ७; ३६, ४; ३७, १; ४४, १२; ४५, १–३; ४७, ३; ६; ४८, ३; ५३, ६; ७; ५४, ४^{६}; ८; १२; ५५, २^{२}; ६; ९; ५९, ६; ६०, १; ६१, ३; ७^{३}; ९; ६२, ७; ६३, २; ५; ७; ६९, २; ७५, ७; ७७, २; ७८, ५; ६; ७९, २^{२}; ३^{२}; ९; ८०, ३; ८१, १; २^{२}; ५; ८३, २; ८; ८५, १–३; ५; ८; **६.** १, ११^{२}; ४, ३; ६; ५, ३; ५; ६, ३; ४; ७, ७^{२}; ८, २; ३^{२}; ९, १–३; ५; ६^{४}; १०, ७; १२, ६; १३, १; ३; १५, १४; १६, ४५; १७, १; ६; ७; १८, ३; ५; २०, ७; २१, ७; २२, ४; ६; ९; २४, ३; ६; २५, ४; २८, ४; २९, ५; ३०, २; ५; ३१, १; ३३, २; ३४, १; ३५, ५; ३७, ३; ४; ३९, २–४; ४०, १; ४४, ६; ८; १०; १६^{२}; २४; ४५, ९; ४७, २; ४८, १७; ५१, १; ५; ५३, ३; ४^{२}; ६; ६२, ७; ११; ६४, २; ६५, २^{२}; ५; ६६, ७; ६७, ७; ८; १०; ६९, ८; ७२, २; ७३, २; ७४, २; ७५, ११; **७.** १, ९; २१; २, ५; ३, २; ४; ६; ४, ७; ५, २; ८, २–४; ९, २; १०, २; १३, ३; १७, १; २; ७; १८, ८; १३^{२}; २१; १९, ९; २०, ३; २१, ४^{२}; २३, ३; ४; २५, १; २८, २; ३२, ७; ३४, १३; २२; ३६, १^{२}; ५; ३७, २; ३८, १; २; ४८,

३; ५६, १३; ५८, ३; ५९, २; ६२, ३; ६६, ११; ६९, ३; ७२, ४; ७५, १; ३; ७७, ५; ७८, १; ७९, १^{२}; २–४; ८६, १; ८८, ७; ९०, ४; ९१, ३; ५; ९५, ३; ६; ९९, ३; १००, ३; ४; १०४, १५; १८; २५; **८.** १, १; ४; ४, १३; ५, १; ९; ६, ६; १३; ७, १; ८; २३^{२}; ९, १६^{२}; १२, १९–२१; १३, ४; २०; १४, ५; ७; १०; १५; १५, ५; १७, ५; २०, ४; ११; २१, ६; २३, ४; २४, २२; २५, १६; २७, ९; १८; २०; २९, ७; ३१, ८; ३२, ५; १९; ३४, ३; ३९, ६; ४०, ६; ४१, १०; ४२, २; ४५, ४; ८; १६; २२; २७; ३०; ४६, ३३; ४७, २; ३; १०; ५४, ६; ५५, १; ५८, २^{२}; ६०, १६; ६१, १३^{२}; ६४, ५; ६७, १२; २१^{४}; ७६, २; ३; ७७, १; ७९, ८; ८२, ६; ८६, १; ५^{२}; ८९, ४; ९१, ५; ९३, १४; २६^{२}; ९४, ११; ९७, १४; १०३, २; **९.** ३, ६–८; ५, १; ३; ७, २; १०, ५; १३, ६; १४, ४; १५, ३; १६, ८; २१, ३; २२, ३; २४, ३; २७, ३; २८, १; ३४, १; ३६, ३; ३७, ३; ३९, ४; ४५, ३; ४९, ४; ५१, ३; ६१, १७; १८; ६४, ३; ६६, ५; २७; ६७, ५^{४}; १४; २१; ६८, ३; ५; ७०, २; ५; ७१, ७; ७४, ४; ९; ७५, ३; ४; ७९, १; ८०, १; ८३, २; ८५, ५; ९; १२; ८६, ८; २१; ३४; ३७; ३८; ४०; ४३; ९०, २; ९१, ३; ४; ९५, ५; ९७, १८; ३२; ३८; ५६; ५८; ९९, ७; ८; १००, ४; १०१, ७; ११; १५; १०२, ३; १०३, ६; १०६, १०; १०७, २३; १०८, ९; १२; १०९, १६; ११०, ६; ९; ११२, १; **१०.** २, ७; ३, १; २; ६; ५, १; १०, ७; ८; ११, २; १२, ५; १३, १; १४, ९^{२}; १६, १; ८; १८, ३; २१, १; २२, ९; २३, १^{२}; ३; ७; २५, २^{२}; ५; २६, ७; २७, ७; १०; १५; १८; २०; २८, ५; ९; २९, ३; ८; ३०, ११; ३१, ९; ३२, २^{२}; ३३, ९; ३४, १३; ३५, ४; ५; ३८, २; ३९, १३; ४०, ९; १०; ४२, ४; ४३, ५; ९; ४४, ८; ४५, ४; ५; ८; ४८, १; ४९, ९; ५४, ५; ५५, ३; ६१, १३; २६, ६२, ३; ९; ६४, १५; ६६, ७; ६७, ४; ६; ७^{२}; १२; ६८, ९; ६९, २; ७०, ४; ५; ७१, ३; ४; ८^{२}; ११; ७३, ८; ७८, ७; ७९, ५; ६; ८०, १; ५; ६; ८१, २; ८३, ३; ८४, २^{२}; ८५, १९; २८; २९; ३३; ४२^{२}; ८६, १; ५; २०; ८७, ५; २५; ८८, १७^{२}; ८९, १; ३; ९०, ४; ११^{२}; ९२, ३; ५; १०^{२}; ९४, १४^{२}; ९५, ३; १२; ९७, १२; ९८, १२^{२}; १०१, ३; ४; १०२, २; १०६, १; १०८, ८; ११०, ५; ११; १११, ६; ११२, ७; ११३, २; ४; ६; ११४, १; २; ४; १०; ११५, ४; ११६, ६; ११७, ८; ११८, ३; १२२, ५; १२४, ३; १२५, ३; ७; १२७, १; १२८, ६; १३०, २; १३१, ५; १३३, ३; १३४, ५; १३७, ३; १३८, १; ३^{२}; ४; १३९, ४; १४०, ४; १४३, २; १४४, ५; १४९, २; १५२, ३^{४}; ४; ५; १५३, ३; १५८, ४; ५; १६०, १; १६३, १; १७०, १; १७७; १; १८०, २^{२}; १८९, २; ३.

विऽअंसः **४.** १८, ९.

विऽअंसं **१.** ३२, ५; १०१, २; १०३, २; **२.** १४, ५; **३.** ३४, ३.

विऽअंक्तः **९.** ७१, ७.

विऽअंक्तं **१०.** १४, ९; १२७, ७.

विऽअंक्ता **७.** ७७, ३; **८.** ५६, ४; **१०.** ८६, ५.

विऽअंक्ताः **७.** ५६, १.

विऽअंक्तां **१०.** ८५, २१.

विऽअंजनं **८.** ७८, २.

विऽअंध्वनः **१.** १४१, ७.

विऽअनत् **१०.** १२०, २.

विऽअर्यनं **१०.** १९, ५.

विऽअंल्कशा **१०.** १६, १३.

विऽअंश्वः **८.** ९, १०; २३, १६.

विऽअंश्वं **१.** ११२, १५.

विऽअंश्वान् **८.** २४, २९.

विऽअंश्वेभ्यः **८.** २४, २८.

विऽअंस्तः **१.** ३२, ७.

विऽअस्यन् **१०.** ६७, ३.

विऽआनः **१०.** ८५, १२.

विऽआनशिः **३.** ४९, ३; **९.** ८६, ५; १०३, ६.

विऽआनशे **९.** ८६, १५.

विऽईव **७.** ५५, २; **१०.** ८६, ७.

विऽउच्छंति **१.** ११३, १८.

विऽउच्छंती **१.** ४८, ९; ४९, ४; ११३, ७; ८; १२४, ८; **४.** ५२, १; **७.** ७९, ५.

विऽउच्छंती **१.** ११३, ११.

विऽउच्छान् **१.** ११३, १०; **७.** ३०, ३.

विऽउंतं **१.** १२२, २.

विऽउंते **३.** ५४, ९.

विऽउंदंति **१.** ३८, ९.

विऽउषिं **५.** ३, ८; ४५, ८; **६.** ६२, १; **७.** ८१, २; **८.** ४६, २१.

विऽउंष्टिषु **१.** ४४, ३; ४; ८; १७१, ५; **२.** ३४, १२; **३.** २०, १; **४.** ४५, २; **८.** २०, १५; **९.** ९८, ११; **१०.** ३५, १; ५; ७६, १; ७७, ५; १२२, ७.

विऽउंष्टौ **१.** ४८, ६; ११८, ११; १२४, १२; **३.** १५, २; **४.** १, ५; १४, ४; २३, ५; ३९, ३; **५.** ३०, १३; ६२, ८; **६.** २४, ९; **७.** ६९, ५; ७१, ३; **१०.** ६, ३; ४१, १; ९९, १.

विऽऊर्णुते **६.** ५०, ८.

विऽऊर्ण्वती **१.** ९२, ११; **५.** ८०, ६.

विऽऊर्ण्वन् **९.** ९४, २.

विऽऊषुः **१.** ११३, १०; **३.** ५५, १.

विऽएंनसा **३.** ३३, १३.

विऽएंनी **५.** ८०, ४.

विऽओदंने **८.** ६३, ९.

विऽओम **१.** १६४, ३४; ३५; **१०.** १२९, १.

विऽओमन् १. ६२, ७; १६४, ३९; ४१; ३. ३२, १०; ४. ५०, ४; ५. १५, २; ७. ५, ७; १०. ५, ७; १४, ८; १०९, ४; १२३, ५; १२९, ७.

विऽओमनः १. ५२, १२.

विऽओमनि १. १४३, २; ५. ६३, १; ८७, ९; ७. ८२, २; ८. १३, २; ९. ७०, १; ८६, १५.

विंशतिः १. ८०, ९; १६४, ११.

विंशतिं ५. २७, २; ६. २७, ८; ७. १८, ११; ८. ४६, २२; ३१; १०. ८६, १४; २३.

विंशत्या २. १८, ५.

विः १. १८२, १; ४. २६, ४; ५; ९. ४८, ४; ६२, १५; १०. ११, ४.

विऽकंटे १०. १५५, १.

विऽक्रस्तं १. ११७, २४.

विऽकृतं २. ३८, ६.

विऽकृतानि १. १६४, १५.

विऽकृत्य १०. ६८, ८.

विक्त १. १६२, १५.

विऽक्रमणं १०. १५, ३.

विऽक्रमणेषु १. १५४, २; ८. ९, १२.

विक्षु १. ४५, ६; ५८, ३; ६०, २; ४; ६६, २; ३; १००, १६; १४८, १; १५३, ४; २. ४, २; ३; २१, ३; ३१, २; ३. ५, ३; ४. ६, २; ७; ८; ७, २; ९, २; ३७, १; ३; ५. १७, ४; ६. १, ६; २, ७; ५, ३; २१, ४; ४१, ५; ७. ३४, १२; ४३, ५; ५६, २२; ६१, ३; ६७, ७; ७०, ३; १०४, १८; ८. ६, २४; २३, १०; ३९, ७; ७१, १५; ९. ३८, ४; १०. १, ४; ७, ५; १५, २; ४०, १४; ४८, ८; ६१, १५; ७९, १; २; ८७, १०.

विऽखादे १०. ३८, ४.

विऽख्यै १०. १५८, ४.

विऽगदेषु १०. ११६, ५.

विगामऽभिः १. १५५, ४.

विऽगाह्य ३. ३, ५.

विग्रं १. ४, ४.

विग्रं ६. ६७, ७.

विऽग्रीवासः ७. १०४, २४.

विऽघनिनो ६. ६०, ५.

विघृते इति विऽघृते ३. ५४, ६.

विऽघ्नन् ९. १७, ३; ३७, १; ५६, १; ९७, १६.

विऽघ्नतः ९. ६२, २.

विऽचक्र ४. ३५, २; ४.

विऽचक्रमाणः १. १५४, १.

विऽचक्रमे १. २२, १६; ८. १२, २७; ५२, ३.

विऽचक्षण १. ५०, ८; ३. ३, १०; ४. ३२, २२; ९. ५१, ५; ८६, २३; १०७, २४; १०. ३७, ८.

विऽचक्षणः १. १०१, ७; ११२, ४; २. २३, ६; ४. ४५, ५; ५३, २; ९. १२, ४; ३७, २; ६६, २३; ७०, ७; ७५, १; ८५, ९; ८६, ११; १९; ३५; ९७, २; १०६, ५; १०७, ३; ५; ७; १६; १०. ९२, १५.

विऽचक्षणं १. १६४, १२; १०. ११, ४.

विऽचक्षणा ८. ४१, ९.

विऽचक्षसे ९. ४५, ६.

विऽचक्षाणः ९. ३९, ३.

विऽचक्षे १. ११३, ५; ११६, १४; १६; ११७, १७; २. २७, १०; ४. १६, ४.

विऽचक्ष्य ८. १३, ३०.

विऽचयिष्टः ४. २०, ९.

विऽचरन् ९. ६८, ४; १०. १४०, २.

विऽचरंतः ८. ५५, ४.

विऽचरंतं १०. ३०, ९.

विऽचरंता १०. ९२, १२.

विऽचरंति १. ५१, १.

विचरंती इति विऽचरंती ६. ४९, ३.

विऽचर्षणिः १. ३५, ९; ७९, १२; २. २२, ३; ४१, १०; १२; ३. २, ८; ११, १; ४. ३६, ५; ६. ४५, १६; ४६, ३; ८. १३, ६; ९. ११, ७; २८, ५; ४०, १; ४४, ३; ४८, ५; ६२, १०; ६७, २२; ८४, १.

विऽचर्षणिं १. ६४, १२; ९. ६०, १.

विचर्षणी इति विऽचर्षणी ५. ६३, ३.

विऽचर्षणे १. ७८, १; ६. १६, २९; ३६; ८. ४३, २.

विऽचर्षणे १. ३१, ६; ६. २, १; ८. १७, ७; ३३, ३; ९८, १०; ९. ४१, ५; ६०, ४.

विऽचाकशत् १. २४, १०; ८. ७३, १७; ९१, २; १०. ८६, १९.

विऽचारिणि ५. ८८, २.

विऽचिनोति १०. ४२, ९.

विऽचिन्वन् ९. ९७, १७; १०. ८६, १९.

विऽचृतं ९. ८४, २.

विऽचृत्ताः २. २७, १६.

विऽचेतसः १. ४५, २; ८३, १; ५. १७, ४; ७. ७, ४; ८. १३, २०.

विऽचेतसः ५. ५४, १२.

विऽचेतसं ४. ७, ३; ८. ४६, १४.

विऽचेतसा ५. ७४, ९; १०. १३२, ६.

विऽचेताः १. १९०, ४; २. १०, १; २; ४. ५, २; ६. २४, २; ७. २७, २; १०. ७९, ४.

विऽच्युताः २. १७, ३.

विजः १. ९२, १०.

विजःऽइव २. १२, ५.

विऽजयंते २. १२, ९.

विऽजयाय १०. ८४, ४.

विऽजर्भृतः १. २८, ७.

विऽजानन् १. ६९, २; ३. ३९, ७; ५. ४९, २; १०. २, ५; ९५, १२; १०७, ७.

विऽजानात् १. १६४, १६.

विऽजानुषः १०. ७७, १.

विऽजामन् ७. ५०, २.

विऽजामातुः १. १०९, २.

विऽजामीन् १०. ६९, १२.

विऽजायते ३. २९, ११.

विजाऽव्ना ३. १, २३.

विऽजृंभते १०. ८६, १६.

विऽजेन्य १. ११९, ४.

विजेषऽकृत् १०. ८४, ५.

विऽजेहमानः ६. ३, ४.

विऽजोपसं ८, २२, १०.

विंचंति १. ३९, ५.
विट् १. ७२, ८; ७. ५६, ५; ९. ८८, ७.
विट्ऽभिः १०. २८, ८.
विऽतक्षत् १. १५८, ५.
विऽततः ९. ७३, ९; १०. १२९, ५.
विऽततं १. ८३, २; ११५, ४; २. ३८, ४; ५. ५४, १२; ९. ६७, २३; ८३, १; २.
विऽतता १. १५२, ४; ६. ७५, ३.
विऽतताः ९. ५४, ११.
विऽततानि ९. ९७, ५५.
विऽतते ९. ७३, ७.
विऽतनोति ५. ४८, १.
वितंतसाय्यः ६. १८, ६; ४५, १३; ८. ६, २२; ६८, ११.
वितंतसैते इति ६. २५, ६.
विऽतन्वते १. ११५, २; ६. ४६, १२.
विऽतरं १. १२३, ११; १२४, ५; २. ३३, २; ४. १८, ११; ५. २९, ४, ६. १, ११.
विऽतरित्रता १. १४४, ३.
विऽतर्तुरं १. १०२, २.
विऽतर्तुराणः ६. ४७, १७.
वितस्तया १०. ७५, ५.
विऽतस्थानां ४. ३०, १२.
विऽतिरे १०. १०४, ५.
विऽतिष्ठन् १०. ३, ३.
विऽतिष्ठसे ८. ६०, १४; १०. ९१, ७.
विऽतूर्य १०. ३, ३.
वित्तं १. १०५, १–१८; ५. ४२, ९.
वित्तं ७. ७२, २.
वित्तऽजानिं १. ११२, १५.
वित्तात् ५. ६०, ६.
वित्ते १०. ३४, १३.
विऽत्वक्षणः ५. ३४, ६.
वित्से ७. ९९, १; १०. ४, ४; ५४, ४.
विथुरं १. १८६, २.
विथुरा ६. २५, ३; ४६, ६.
विथुराऽइव १. ८७, ३; १६८, ६.
विथुरेण ८. ९६, २.
विथुर्यति १०. ७७, ४.
विद १. ८६, ८; १५६, ३; ५. ४१, १३; ५५, २; ८. ४७, २.
विदः ५. ३०, ४.
विदः १. ४२, ७–९; १७३, १३; ४. १, ३; ९. २०, ३; ५९, ४; १११, २.
विदत् १. ६१, ६; ६२, ३; ७२, ४; ८; ९६, ४; २. १९, ३; ३. ३१, ६; ४. २१, ८; ५. ७, ६; ३२, ५; ८. ६९, ६; ७९, ६; ९३, १४; ९. ९६, १०; १०. २१, ५; ४३, ४; ६१, १३; ६८, ११; ७६, २; ९९, ८; १२३, ४; १३८, ३.
विदत् १. ८४, १४; १००, ८; १८९, ४; २. ४२, १; २; ५. ४४, ८; ४५, ८; ६. ४७, ५; ७. ५०, १; ९. ६८, ९; १०. ८६, १८.
विदतं १. १५१, २.
विदत्ऽवसुः ३. ३४, १.
विदत्ऽवसुं १. ६, ६; ८. ६६, १.
विदथं १. ११७, २५; २. १२, १५; ७. ९३, ३; ८. ४८, १४; १०. ८५, २६; २७.
विदथस्य १. ५६, २; ६०, १; ३. ३, ३; ३८, ५; ५. ३३, ९; १०. ९१, ८; ९२, २.
विदथा १. १६४, २१; ३. १, २; ४. ३८, ४; ६. ८, १; ११, २; ८. ३९, ९.
विदथानि ३. १, १८; १४, १; २७, ७; ४. १६, ३; ६. ५१, २; ७. ६६, १०.
विदथानिऽइव १. १३०, १.
विदथाय १०. ११, ३.
विदथुः १. १८२, ४.
विदथे १. ३१, ६; १५१, १; १५३, ३; १६२, १; १८६, १; २. १, ४; १६; २, १३; ४, ८; ११, २१; १३, १३; १४, १२; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; २३, १९; २४, १६; २७, ८; १७; २८, ११; २९, ७; ३३, १५; ३५, १५; ३९, १; ८; ४०, ६; ४२, ३; ४३, ३; ३. १, १; ८, ५; ३८, ६; ३९, १; २; ५४, ११; ५६, ५; ५. ५९, २; ६३, २; ६. २४, २; ५२, १७; ७. १८, १३; २१, २; ९३, ५; ९. ९२, १; १०. १२, ७; ९६, १; १००, ६.
विदथे इति ८. ३९, १.
विदथेषु १. ४०, ६; ६४, १; ६; ८५, १; ८९, ७; ९२, ५; १४३, ७; १५३, २; १५९, १; १६६, २; ७; १६७, ६; २. २७, १२; ३. ४, ५; २६, ६; २८, ४; ५४, २; ५५, ७; ५६, ५; ४. ६, २; २१, ४; ३६, ५; ५. ३, ६; २९, १३; ७. ५७, २; ७३, २; ८४, ३; ९९, ६; ८. ११, २; ९. ९७, ५६; १०. ९१, ९; ११०, ७; १२२, ८.
विदथ्यः ४. २१, २.
विदथ्यं १. ९१, २०; ६. ८, ५; ७. ३६, ८; १०. ४१, १.
विदथ्या ७. ४०, १.
विदथ्याऽइव १. १६७, ३.
विदथ्यां ७. ४३, ३.
विदथ्याय ३. ५४, १.
विदद्वसो इति विदत्ऽवसो ५. ३९, १.
विऽदधत् ६. ६२, ९; १०. ८५, १८; १९०, २.
विऽदधुः ४. ५१, ६.
विदन् ८. २८, १.
विदन् १०. ८५, ३२.
विदंत ४. १, १४.
विदंति १. ६७, २.
विद्रुं २. २७, १७; २८, ११; २९, ७; १०. ४९, ९.
विऽदयते १. ८४, ७.
विदा १. ३१, १८.
विदाः १. ३६, १४; ७१, ७; ५. ४५, १; ६. ४८, ९; ८. ६१, ७; ९. १९, ६; ४०, ४; ४३, ४; ६३, ११.
विदात् २. २२, ४.
विदाथ १०. ८२, ७.
विदाथः १०. १०६, ९.
विदानः १. १६५, ९; १०; २. ९, १; ६. २१, २; १२; ८. ४५, २७; १०. १११, १.

वि॒दा॒नः ९. ३५, ४.
वि॒दा॒ना ५. ८०, ५.
विदा॑नाः ३. ३६, २.
वि॒दा॒नाः ९. ७, १; ८.
वि॒दा॒नासः॑ १. १६९, २; ४. ३४, २; १०. ७७, ६.
विदा॑ने॒ इति॑ १. १२२, २; १०. १३, २.
वि॒दाय्यः॑ १०. २२, ५.
वि॒दासि॑ ९. ३५, १.
वि॒ऽदि॒द्यु॒ता॒नः ६. १६, ३५.
वि॒दुः १. ११, ६; ७; १९, ३; ७१, १०; १३१, ४; १६४, २३; ३९; १६६, ७; ३. ५५, १८; ४. ४२, ७; ५. ४४, ११; ५९, ७; ७. १८, २; ३४, २; ८. १८, ५; ६३, ६; ६७, २; ९. ७०, २; १०. ८५, ३; ११४, १.
वि॒दुः १. ३४, २; १३९, ९[२]; १६४, ४५; २. २३, १६; ३. २९, १५; ७. ३३, ७; १०. ५०, ५; ८५, १६[२]; १०८, १०.
वि॒दुःऽत॑रः १. ३१, १४; १०५, १३; १४; २. १६, ४; ४. ७, ८; ६. १६, ९; ७. १६, ९; ८. ७५, २.
वि॒दुःऽत॑रं ६. १५, १०.
वि॒दुःऽत॑रा २. ३, ७; १०. ७०, ७.
वि॒दुःऽत॑रेभ्यः ८. ४१, १.
वि॒दुषः॑ ३. १४, २.
वि॒दुषा॑ १. १५६, १; ५. ४४, १०; ६. ५४, १.
वि॒दुषा॑ १०. २, ४.
वि॒दुषी॑ १०. ९५, ११.
वि॒दुषी॑ इ॒वेति॑ वि॒दुषी॑ऽइव ५. ४१, ७.
वि॒दुषे॑ १. ११७, १०; २. ३०, २; ४. ३, १६; १९, १०; ६. ४२, १.
वि॒दे १. १००, १०; १२७, ४; १३२, २; ६. ६६, ३; ७. ४०, ५; ८. १३, १; १४; २९; ४९, १; ६२, ९; ६९, ४; ९३, ३२; ९. १४, ६; ८६, ३२; ९९, ७; १०६, २; १०. २३, २.
वि॒दे॒ १. १२०, १२; १३२, ३; ८. ४५, ३६.
वि॒दो इति॑ १०. ११३, १०.
वि॒द्धि २. २०, १; ३२, २; ३. ३९, १; ७. ३१, ४; १०. ६१, २२.
वि॒द्धि॒ ८. ४८, ८; १०. २७, २४; ८५, २१.
वि॒द्म १. १०, १०; ८१, ८; १७०, ३; ३. ३६, ९; ४२, ६; ५. ८५, ८; ६. २१, ६; २७, ३; ८. २, २१; २०, ३; २१, ७; ८; ४५, १३; ४६, २[२]; ५१, ५; ६१, ३; ७५, १६; ८१, २; ९२, १८; १०. १५, १३; २३, ६; ७; ४५, २[४]; ४७, १.
वि॒द्म॒ ५. ४८, ५; ७. ९९, १; ८. २, २२; १०. १२, ८; ४०, ११.
वि॒द्मना॑ १. ११०, ६; ५. ८७, २; ६. १४, ५; ७. ४, १.
वि॒द्म॒नाऽअ॑पसः १. ३१, १; ११२, १.
वि॒द्मने॑ १. १६४, ६; १०. ८८, १८.
वि॒द्यते॑ ५. ४४, ९.
वि॒द्य॒ते १०. ६४, २.
वि॒द्यात् १०. ८५, ३४.
वि॒द्या॒त् १. २३, २४.
वि॒द्यात॑ ८. ५, ३७.
वि॒द्यां २. २७, ५.
वि॒द्याम॑ १. ४, ३; १६५, १५; १६७, ११; १६८, १०; १६९, ८; १७१, ६; १७३, १३; १७४, १०; १७५, ६; १७६, ६; १७७, ५[२]; १७८, ५; १८०, १०; १८१, ९; १८२, ८; १८३, ६; १८४, ६; १८५, ११; १८६, ११; १८९, ८; १९०, ८; ५. ३९, २; ८. २४, ८; ५०, ९; १०. २२, १३; ८९, १७.
वि॒द्युः १. २३, २४.
वि॒ऽद्यु॒त् १. ३२, १३; ३८, ८; ६४, ९; १६४, २९; ६. ३, ८; ९. ७६, ३; ८७, ८; १०. ९५, १०.
वि॒ऽद्युतः॑ १. २३, १२; ३९, ९; ६४, ५; १६८, ८; ३. १, १४; ५. १०, ५; ५२, ६; ५४, ११; ८३, ४; ८४, ३; ७. ३३, १०; ५६, १३; ९. ४१, ३; १०. ९१, ५.
वि॒ऽद्यु॒तः १. १०५, १.
वि॒ऽद्युत॑ २. ३५, ९; ७. ६९, ६.
वि॒ऽद्युता॑ १. ८६, ९; ५. ४२, १४; ५४, २; ९. ८४, ३; १०. ९९, २.
वि॒द्यु॒त्ऽम॑हसः ५. ५४, ३.
वि॒द्यु॒त्ऽर॑थः ३. १४, १.
वि॒द्यु॒त्ऽर॑थाः ३. ५४, १३.
वि॒द्यु॒त्ऽह॑स्ताः ८. ७, २५.
वि॒द्युन्म॑तऽभिः १. ८८, १.
वि॒द्र॒धे ४. ३२, २३.
वि॒द्रे १. ८७, ६.
वि॒द्रे॒ ७. ५६, २.
वि॒दुला १०. १५९, १.
वि॒द्वांसः॑ २. २४, ६; ४. ३६, ८; १०. ५३, १०.
वि॒द्वांस॑ १. १६४, ४.
वि॒द्वांसा॑ १. ११६, ११; १२०, ३[२]; ५. ८६, ४.
वि॒द्वांसौ॑ १. १२०, २.
वि॒द्वान् १. २४, १३; ७०, ३; ७२, ७; ९०, १; ९४, ६; १६; १०३, ३; १२०, ५; १४५, ५; १५२, ६; १६४, ६; १८९, १; ७; १९०, ७; २. ५, ४; ८; ६, ७; ८; १५, ७; २९, १; ३. १, १७; १८; ५, ६; १४, २; १७, ३; २५, २; २९, १६; ३१, १; ३५, ८; ४४, २; ४७, २; ५२, ७; ५५, १४; ४. १, ४; २, ११; ७, ८; ८, ४; १६, ६; ३०, १७; ४२, ३; ५. १, ११; २, ८; ३, ९; ४, ५; २९, १३; ३०, ३; ४६, १[२]; ४९, २; ६. १५, १०; २१, ११; ४४, १४; ४७, ८; ७५, १४; ७. १, २४; ७, १; १०, २; २१, ४; २२, ५; २८, १; ८७, ४; १००, ५; ८. ६३, ३; ७२, १; ९२, ९; ९. ७०, १०; ७३, ८; ७७, ४; ८१, २; ९६, २; १०. १, ३; २, १; ३; ४; ५, ५; ८, ८; १७, ३; २७, ११; २८, ५; ५२, ४; ५३, १; ६७, ३; ७०, ९; १०; ९८, ११; १०२, ७; ११०, ९; १२२, २; १३६, ६; १३९, १; १४८, ३; १६०, २.

विऽद्वेषणं ८. १, २.

विऽद्वेंषसं ८. २२, २.

विऽधक्ष्यन् १०. १६, ७.

विधन् ८. ५, २२.

विधतः १. ७३, १; १६७, ५; २. १, ६; ४. २, १०; ५. ६५, ४; ६. ३, ७; ८. ६१, १४; ७८, ७; ९९, ४; १०. ९३, ८.

विधते १. ११९, ७; २. १, ५; ३५, ७; ४. २, १३; १२, ३; ३४, ४; ४४, ४; ६. १, १३; ५, ३; ६५, ३; ४; ६; ७. १६, १२; ७५, ६; १०. ४६, १.

विधन् १. १४९, १.

विधंत ३. ३, १.

विधंतः २. ४, २.

विधंतं ३. ४, २; ८. २, ३६; १०. ४०, ८.

विऽधर्तारं ८. ७०, २; ९. ४७, ४.

विधर्तेरिति विऽधर्तः २. १, ३.

विऽधर्ता २. २८, ४; ७. ७, ५; ४१, २; ५६, २४.

विऽधर्मणा १०. ४६, ६.

विऽधर्मणि १. १६४, ३६; ३. २, ३; ६. ७१, १; ९. ४, ९; ६४, ९; ८६, २९; ३०; १००, ७.

विऽधर्मणे ८. ७, ५.

विऽधर्मन् ९. ९७, ४०; १०९, ६; १०. १२३, ८.

विऽधर्मन् ५. १७, २.

विधवाऽइव १०. ४०, २.

विऽधवा ४. १८, १२; १०. ४०, ८.

विधातुरिति विऽधातः १०. १६७, ३.

विऽधाता ६. ५०, १२; ९. ८१, ५; १०. ८२, २; ३.

विऽधातारः ४. ५५, २.

विधाति १. १२०, १.

विऽधाने १०. १३८, ६.

विऽधाना ४. ५१, ६.

विऽधारे ९. ११०, ३.

विऽधावतः १. ८८, ५.

विऽधुं १०. ५५, ५.

विधेम २. ९, ३[२].

विधेम १. ३६, २; ११४, २; १८९, १; २. ६, २; २४, १; ३५, १२; ४. ४, १५; ५०, ६; ५. ४, ७; ६. १, १०; ७. १४, २; ६३, ५; ८. २३, २३; ४३, ११; ४८, १२; १३; ५४, ८; ९६, ८; १०. १२१, १; १६८, ४.

विधेमहि ८. १९, १६.

विध्यं ४. ४, १.

विध्य २. ३०, ४; ९; ४. ४, ५; १०. ८७, ४; ६; १३; १७; ८९, १२.

विध्यंत् १. ६१, ७.

विध्यंत १. ८६, ९.

विध्यतं ७. १०४, ३; ५.

विध्यतां ६. ७५, ४.

विध्यति ४. ८, ८; ९. ७३, ८.

विनंऽगृसः ९. ७२, ३.

विऽनयः २. २४, ९.

विऽनाशयंन् १. ५५, ६.

विऽनिक्षे ५. २, ९.

विऽनुदः २. १३, ३.

विंदु ७. १३, ३; १८, १८.

विंदुः १०. १०४, ८.

विंदुत् ६. ४४, २३.

विंदति ९. ६७, २१.

विंदुति १०. ३२, ७.

विंदुतीँ३ १०. १४६, १.

विंदते ६. ५१, १६.

विंदुते ६. ५४, ४; ७. ३२, २१; ८. २३, ३; २७, १७; ७२, ५; १०. ३४, ३; ११७, १; २; ६; १५१, ४.

विंदुन् १. ७२, २; ४. १, १६.

विंदंति १. १०५, १.

विंदमानः ३. ५५, २०.

विंदुसि १. १७६, १; १०. ८६, २.

विंदसे २. १३, ११.

विंदुसे ८. २१, १४.

विंदामि ८. २४, १२; ४६, ११.

विंदामि १०. ३४, ३.

विंधते ८. ५१, ३.

विंधते ८. ९, ६.

विंधे १. ७, ७.

विपः ३. ३, १; ४. ४८, १; ६. ४४, ६; ४९, १२; ८. १, ४; १९, ३३; १०. ६१, ३.

विपः ८. ६३, ७.

विपःऽचित् ९. १२, ३; ९६, २२.

विपःऽचितः १. १८, ७; १६४, ३६; ४. ३६, ७; ५. ८१, १; ८. १, ४; ३, ३; ४३, १९; ६५, ९; ९. २२, ३; ३३, १; १०१, १२; १०. १७७, १.

विपःऽचितं १. ४, ४; ३. २६, ९; २७, २; ८. १३, १०; ९. १६, ८; ६४, २५; ८६, ३६.

विपःऽचिता ५. ६३, ७.

विपःऽचितो ३. ३, ४.

विपःऽचिते ८. ९८, १; ९. ८६, ४४.

विपःऽधां १०. ४६, ५.

विऽपक्षसा १. ६, २.

विऽपत्मनः १. १८०, २.

विपथयः ५. ५२, १०.

विपन्यया १. ११९, ७; ३. २८, ५; ६. १६, ३४; १०. ७२, १.

विपन्यवः १. २२, २१; १०२, ५; १३८, ३; २. २०, १; ३. १०, ९; ५. ४३, १४; ७. ९४, ६; ८. २२, ११; ८७, ६.

विपन्युवः ५. ६१, १५.

विपन्या ४. १, १२.

विपन्यामहे १. १८०, ७.

विपन्युऽभिः ८. १९, १०; ९. ३, ३.

विपन्युवः ९. ८६, १७.

विपन्यू इति ८. ८, १९.

विपर्यंति ७. २१, २.

विऽपर्वं १. १८७, १.

विऽपश्यति ३. ६२, ९; १०. १२५, ४.

विपा ५. ६८, १; ९. ३, २; २२, ३; ६५, १२; १०. ९९, ६.

विऽपाका १. १६८, ७.

विऽपाद् ३. ३३, १.

विपानः ८. ६, २९.

विपां ३. ३, ७; १०, ५; ८. ६, ७; ९. ९९, १.

विऽपाशं ३. ३३, ३.

विऽपासि ४. ३०, ११.

विऽपिपानः ४. १६, ३.
विऽपिपानं १. ११२, १५.
विऽपिपानस्यं ७. २२, ४.
विऽपिपाना १०. १३१, ४.
विऽपृक्तः १. १६३, ३.
विपृक्वत् ५. २, ३.
विऽपृचें ४. १३, ३.
विऽपृच्छते ९. ७०, ९.
विऽपृच्छें ७. ८६, ३.
विऽप्रेततुः १०. ९६, ९.
विप्र १. १४, २; १२७, २; १३०, ६; १५०, ३; २. ३६, ४; ४. १९, १०; ५. ३१, ७; ५१, ३; ५८, २, ६. ३५, ५; ३८, ५; ८. १९, २; १७; ७१, ५; १०२, १२; १०. ५०, ७; ८७, २४.
विप्रंः १. १४, ९; २. २४, १३; ३. ५, १; ३; ८, ५; १३, ३; १४, ५; २७, ८; २९, ७; ३३, ४; १२; ४. ३, १६; ८, ८; २६, १; ५. २, ११; ४३, १; ७४, ७; ६. ७, ३; १०, ३; ११, ३; १३, ३; ५१, २; ६८, ३; ७. ५८, ४; ६१, २; ६८, ४; ७२, ३; ८७, ४; ८८, ४; ६; ९३, ४; ८. २, ३६; ३, १४; ६, २८; ७, १; ८, ९; १२, ३१; ३९, ९; ४२, ५; ४३, १४; ४४, २१; २९; ४६, ३२; ६१, ९; ७९, १; ९. १८, २; ८४, ५; ८७, ३; ९७, ३७; १०७, ६; ७; १०. २६, २; ६१, १६; २३; २४; ६४, १६; ९७, ६; १४८, ३; १६५, २.
विप्रंऽजूतः १. ३, ५.
विप्रंऽतमः ३. ३१, ७.
विप्रंऽतमं १०. ११२, ९.
विप्रं १. ५१, १; ८६, ३; ११२, १३; ११९, ७; १२७, १; १६५, १४; ३. २, १३; २६, २; ४. २९, ४; ५. १, ७; ४१, ६; ६. १५, ४; ७; ८. ७, ३०; ११, ६; ४४, १०; ९. १३, २; ४०, १; ६५, २९; ६६, ८; १०. ६७, २; ८७, २२.
विप्रंऽमन्मनः ६. ३९, १.
विऽप्रयंतः ९. २२, ५.
विप्रऽराज्यें ८. ३, ४.
विप्रंऽवचसः ८. ६१, ८.
विप्रऽवाहसा ५. ७४, ७.
विप्रंऽवीरः ९. ४४, ५.
विप्रंऽवीरं १०. ४७, ४; ५.
विप्रंऽवीरस्य १०. १८८, २.
विप्रंऽवीराः १०. १०४, १.
विप्रंस्य १. १७, २; ७६, ५; ८५, ११; ८६, २; १२९, ११; १४२, २; १५१, ६; ५. ८१, १; ६. १६, ६; ७. २२, ४; ५६, १५; ८. १९, १२; ४३, १; ९. १२, ८; ४३, ३; ६; ४४, २; १०. ११, ५; २५, १०; २६, ५; ३९, ८; ४०, १४; ४१, ३.
विप्रां ७. २, ७; ४३, १; ४४, २; ६६, ८; ८. २५, २४.
विप्रा ६. ५०, १०.
विप्राः १. २२, १४; २३, ३; ४५, ७; ८; ८२, २; १६२, ७; १६४, ४६; २. ११, १२; १८, ३; ३. ७, ७; १०, ९; २७, ११; ३०, २०; ३१, ५; ३४, ७; ४७, ४; ६२, १२; ४. २, १५; १७, १६; २९, ५; ५०, १; ५. १३, ५; ३०, १५; ४३, ७; ८१, १; ६. ७०, ४; ७. २२, ९; ३१, ११; ९३, ३; ८. ६, २; ३३; १२, १३; १३, १७; २३, २५; ४२, ४; ६६, १३; ९७, १२; ९. ८, ४; १२, २; १७, ६; ७; ६३, २०; २१; ६४, २३; ८६, ३९; ९२, २; ९७, ३५; १०. ४३, ७; १०८, ११; ११४, ५; १२०, ४; १२३, १; ४.
विप्राः ३. ५३, १०; ७. ३८, ८; १०. ४२, १.
विप्राणां ५. ७६, १; ९. ८५, ७; ९६, ६; १०. २६, ४.
विप्रान् ६. १७, १४.
विप्राय १. ११७, ११; १८२, ३; ३. २१, ३; ५. ६१, ९; ६. ६५, ४; ८. ४३, १५; ९८, १; ९. ४७, ४; १०. २५, ११.
विप्रासः १. ८, ६; २२, २१; ११८, ३; ३. ३, ३; ११, ८; ५. ८०, १; ६. २२, २; ७. १५, ९; ७८, २; ८०, १; ९४, ५; ८. ३, १८; ९, ३; ११, ५; ६; १९, १७; २१, ४; ५१, १०; ६०, ५; ८७, ६; ९. २६, १; ८६, २४; १०७, २४; १०८, ४; १०. ६, ५; ३०, ४; ७८, १.
विऽप्रुतं १. ११६, २४; ११७, ४.
विप्रेण ८. ४३, १४; ४४, १२.
विप्रेभिः १. २०, १; २७, ९; ७७, ५; १२७, २; ५. ५१, ३; ६. ३३, २; ८. ६०, ३; ८१, ८; ९. १०७, ११.
विप्रेभ्यः ५. ३२, १२; १०. १३५, ४.
विप्रैः १. ६२, ४; १२९, २; ९. ३, ६.
विप्रौ ८. २६, ९.
विऽबभ्रते १. २८, ४.
विऽबबाधे १०. ८९, १.
विऽबभाज ७. १८, २४.
विऽबाधः १०. १३३, ४.
विऽबाध्य २. २३, ३.
विऽबाल्यं ४. ३०, १२.
विऽबोधनं ८. ३, २२.
विऽभक्ता ३. ४९, ४.
विऽभक्ता १. २७, ६; ४. १७, ११; ५. ४६, ६; ६. ३६, १; ७. १८, २४; २६, ४; १०. १४७, ५.
विऽभक्तारं १. २२, ७.
विऽभजन् १. १०३, ६.
विऽभजंतः २. १३, ४.
विऽभजंतं ५. ४९, १; २.
विऽभजासि १. १२३, ३; १०. ११, ८.
विऽभंजनुः ४. १७, १३.
विऽभराः ५. ३१, ६.
विऽभवः ३. ६, ९.
विऽभागे १. १०९, ५; ५. ७७, ४; ७. ३७, ३; ४०, १; ५६, २१.
विऽभाति १. ७१, ६; २. ८, ४; २३, १५; ३५, ८; ६. ६८, ९; ७. ९, ४; १०. ६, २; १२१, ६.
विऽभाती १. ९२, ६; १२३, १०; १२४, ६.

विऽभार्को: १. ११३, १७; १२३, ६; ३. ६, ७; ४. २, १९; ५१, १; १०; ११; ७. ३५, १०; ७८, ३; ५; १०. ८८, १२.

विऽभातीनां १. ११३, १५; ४. १३, १.

विऽभातीं ३. ६१, ५; ६; ५. ८०, १; ७. ७८, ४.

विऽभानां १०. ५५, ४.

विभानो इति विऽभानो ८. १०२, २.

विभाऽवः १. ५८, ९.

विभाऽवं १. १४८, १.

विभाऽवरि १. ३०, २०; ४८, १; १०; ९२, १४; ४. ५२, ६; ५. ७९, ४; १०; ८. ४७, १४.

विभाऽवंसुः ३. २, २; ८. ४३, ३२; ४४; २४; १०. ११८, ४.

विभाऽवंसुं ५. २५, २; ८. ४४, ६; १०; १०. ९२, १.

विभावसो इति विभाऽवसो १. ४४, १०; ५. २५, ७; ८. ९३, २५; १०. १४०, १.

विभाऽवा १. ५९, ७; ६६, १; ६९, ५; १४८, ४; ३. ३, ९; ४. १, ८; १२; ५. १, ९; ४, २; ६. ४, २; १०, १; ११, ४; ४९, ९; १०. ६, १; २; ८, ४; ६१, २०; ८८, ७; ९१, १.

विऽभासिं १. ९२, ८; ६. ४८, ३.

विऽभिः १. ४६, ३; ११७, १४; ११९, ४; ५. ५३, ३; ७४, ९; ७५, ५; ६. ६२, ६; ८. २९, ८.

विऽभिद्यं १०. ६७, ५.

विऽभिनत्ति ८. ३३, ७.

विऽभिंदुता १०. १३८, ५.

विऽभिंदन् १. १०३, ३.

विऽभिंदुनां १. ११६, २०.

विभिंदो इति विऽभिंदो ८. २, ४१.

विऽभिन्नं १०. १३८, ६.

विऽभीदकः ७. ८६, ६; १०. ३४, १.

विऽभीषणः ५. ३४, ६.

विऽभु १. ९, ५; १६५, १०; २. २४, १०; ८. १०१, १२.

विऽभुः १. ३१, २; ३४, १; ६५, ५; १४१, ९; २. २४, ११; ५. ४, २; ५, ९; १०. ९१ १.

विभुऽक्रतुं ८. ६९, १५.

विभुऽभिः ७. ४८, २.

विऽभुं ६. १५, ८.

विभुमतऽभ्यः ८. ९६, १६.

विभुऽवंसुः ९. ७२, ७; ८६, १०.

विभूतऽद्युम्नः १. १५६, १; ८. २३, ६.

विऽभूतं १०. १८३, १

विऽभूतयः १. ८, ९; १६६, ११.

विभूतऽरातिं ८. १९, २.

विऽभूतिः १. ३०, ५; ६. २१, १.

विऽभूतिं ६. १७, ४; ८. ४९, ६; ५०, ६.

विऽभूपति १. ११२, ४.

विऽभूपन् ६. १५, ९.

विऽभृतः १. ७१, ४; १४४, २; ३. ५५, ४; १०. १, २.

विऽभृता १०. ४५, २; ८०, ४.

विभृते इति विऽभृते १०. ७९, १.

विऽभृत्रः २. १०, २.

विऽभृत्रं १. ९५, २.

विऽभृत्राः १. ७१, ३; ७. ४३, ३.

विऽभृत्वा ९. ९६, १९.

विऽभ्यः २. ३८, ७; ४. २६, ४.

विऽभ्राजंते ८. ४३, २२.

विऽभ्राजन् ८. ९८, ३.

विऽभ्राजंते ५. ६१, १२.

विऽभ्राजमानः ७. ६३, ३.

विऽभ्राजमानान् ४. ३३, ६.

विऽभ्राट् १०. १७०, १; २.

विऽभ्राष्टिं १. १२७, १.

विऽभ्वः ४. ३४, ९; ७. ४८, १; २.

विऽभ्वः १. १६६, ११; ३. ३१, १६; ६. ३४, १.

विऽभ्वः ४. ३६, ३.

विभ्वऽतष्टः ४. ३६, ५.

विभ्वऽतष्टं ३. ४९, १; ५. ५८, ४.

विभ्वऽतष्टाः ५. ४२, १२.

विऽभ्वना १०. ७६, ५.

विऽभ्वने ६. ६१, १३.

विऽभ्वे ३. ३१, १३; ४. ७, १; १०. ११, ४; ४०, १.

विभ्वऽसहं ५. १०, ७; ९. ९८, १.

विऽभ्वा १. ११३, १; १६१, ६; १९०, २; ४. ३३, ३; ९; ३४, १; ३६, ६; ५. ४६, ४; ७. ४८, ३; १०. ३, ६.

विऽभ्वा १०. १३८, ५.

विऽभ्वी ५. ३८, १.

विऽभ्वीः १. १८८, ५.

विऽभ्वे ८. ९६, ११.

विं ३. ४५, १; १०. ११५, ३.

विऽमंहते ८. ४५, १२.

विऽमदः १०. २०, १०.

विऽमदस्य १०. २३, ७.

विऽमदाः १०. २३, ६.

विऽमदाय १. ५१, ३; ११२, १९; ११६, १; ११७, २०; ८. ९, १५; १०. ३९, ७; ६५, १२.

विऽमदेन १०. २४, ४.

विऽमध्यं १०. १७९, २.

विऽमध्ये ४. ५१, ३.

विऽमनाः ८. ८६, २; १०. ८२, २.

विऽमन्यवः १. २५, ४.

विऽममे १. १५४, १; ३; २. १२, २; ५. ८१, ३; ६. ४९, १३.

विऽमहसः ५. ८७, ४.

विऽमहसः १. ८६, १.

विऽमहीनां ८. ६, ४४.

विऽमानः ३. २६, ७; ७. ८७, ६; ९. ६२, १४; ८६, ४५; १०. १२१, ५; १३९, ५.

विऽमाने २. ४०, ३; ३. ३, ४.

विऽमानीं १०. ९५, १७.

विऽमाने १०. १२३, १.

विऽमाय १०. ११४, ६.

विऽमाय १०. ७३, ७.

विऽमितानि ६. ७, ६.

विऽमिन्वन् ४. ५६, १.

विऽमिमानः १. १५५, ६; १८६, ४.

विंऽइव २. २९, ५.

विऽमुचः १. ४२, १; ६. ५५, १.

विऽमुचंति ५. ६२, १.

विऽमुचं ५. ४६, १.

विऽमुच्यं १. १०४, १; ३, ३२, १.

विऽमृधः १०. १५२, २.
विऽमृशंतः १०. ६५, ७.
विऽमृष्टं १०. ८८, १६.
विऽमोचन ८. ४, १५; १६.
विऽमोचनं २. ३७, ५; ३. ३०, १२; ५३, ५; ४. ४६, ७.
विऽमोचनात् ३. ५३, २०.
विऽमोचने ५. ५३, ७; १०. ९४, १३.
विऽयंतं ४. १९, ३.
विऽयंतः ४. २८, ९; १०. ५, ३; ६१, २७.
विऽयंता १. १६४, ३८; १०. ६१, ६.
विऽयंति ७. ४३, १.
विऽयाति ८. ७३, १३.
विऽयुता ४. ७, ७; १०. ६१, १२.
विऽयुताः ५. ३०, १०.
वियुते इति विऽयुते ३. ५४, ७.
विऽयूयं १०. १३१, २.
विऽयेमिरे ४. ५४, ५.
विऽयोतारः ४. ५५, २.
विऽयोषत् ४. १६, २०.
विऽरप्शं ४. ५०, ३; ७. १०१, ४.
विऽरप्शिन् ६. २२, ६; ४०, २.
विऽरप्शिनः १. ६४, १०; ८७, १; १०. ७५, ९; ११३, ६.
विऽरप्शिनः १. १६६, ८.
विऽरप्शिनं ८. ७६, ५; १०. ११५, ३.
विऽरप्शिने ६. ३२, १.
विऽरप्शी १. ८, ८; ३. ३६, ४; ४. १७, २०; २०, २.
विऽरवेण १०. ६८, ८.
विऽराजः १०. ९०, ५.
विऽराजतः १. १८८, ६.
विऽराजथ १. १८८, ४.
विऽराजे ९. ९६, १८; १०. १६६, १.
विऽराजानि १०. १५९, ६.
विऽराट् १. १८८, ५; १०. ९०, ५; १३०, ५; १५९, ३.
विरापाट् १. ३५, ६.
विरुक्मतः १. ८५, ३.
विरुक्मता १. १२७, ३; १०. २२, ४; १३८, ४.
विरुक्मान् ६. ४९, ५.

विऽरुद्रस्य १. १८०, ८.
विऽरुरुचुः ४. ७, १.
विऽरूप ८. ७५, ६.
विऽरूपं ३. १, १३.
विरूपऽवत् १. ४५, ३.
विऽरूपा ३. ३८, ९; १०. ९५, १६.
विऽरूपाः १. ७०, ४; ३. ५३, ७; ७. १०३, ६; १०. १६९, २.
विऽरूपासः १०. ६२, ५; ६.
विरूपे इति विऽरूपे १. ६२, ८; ७३, ७; ९५, १; ११३, ३; ३. ४, ६; ५. १, ४; ६. ४९, ३.
विऽरोकिणः ५. ५५, ३; १०. ७८, ३.
विऽरोके ३. ५, २.
विऽरोचमानः ५. ४४, २.
विऽरोचमानं १. ९५, २; ९.
विऽरोचयन् ९. ३९, ३.
विवक्तन १. १५६, ३.
विवक्ति ७. ६८, ४; १०. ११, ६.
विवक्ति ७. ७२, ३; ९. ९६, १९; ९७, ७; १०. १२०, ८.
विवक्मि १. १६७, ७; ३. ५७, ४; ४. २०, ५; ७. ६, १; २२, ५; ६७, १.
विवकान् ७. ६७, ३.
विवक्षणं ८. ४९, ४.
विवक्षणस्य ८. १, २५; ३५, २३.
विवक्षणाः ८. ४५, ११.
विवक्षणे ८. २१, ५.
विवक्षसे १०. २१, १–८; २४, १–३; २५, १–११.
विऽवरे १. ११२, १८.
विऽवर्तनं १. १६२, १४.
विऽवर्तयंती ७. ८०, १.
विऽववृधे ९. १०८, ८.
विवव्री इति विऽवव्री १०. ९९, ५.
विवष्टि ७. १६, ११.
विवस्वं १. १८७, ७.
विवस्वत् १. ४४, १.
विवस्वतः ८. ६, ३९; १०. १७, १.
विवस्वतः १. ५३, १; ५८, १; ३. ३४, ७; ५१, ३; ४. ७, ४; ५. ११, ३; ६. ८, ४; ८. ३९, ३; ६७, २०; ७२, ८; ९. १०, ५; १४, ५; २६, ४; ६६, ८; ९९, २; १०. १२, ७; २१, ५; ३९, १२; ६३, १; ७५, १.
विवस्वतं १०. १४, ५.
विवस्वता १. ९६, २.
विवस्वति ८. ५२, १.
विवस्वति १. ४६, १३; १३९, १; २. १३, ६.
विवस्वते १०. १७, २.
विवस्वते १. ३१, ३; १०. ६५, ६.
विवस्वत्याः ३. ३०, १३.
विवस्वऽभिः ८. १०२, २२.
विवस्वान् ७. ९, ३.
विऽवाचः ३. ३४, १०; ६. ३१, १; ३३, २; १०. २३, ५.
विऽवाचनी १०. १५९, २.
विऽवाचि १. १७८, ४; ६. ४५, २९; ७. २३, २; ३०, २.
विवायं १. १५६, ५; १०. ६, २.
विवाय १. ७१, ४; ७. ६, ३.
विवास ५. ८३, १; ८. ९६, १२; १०. ६३, ५.
विवासत ७. १५, ६; ८. १५, १.
विवासतः ८. ३१, ७.
विवासति १. ५८, १; ५. ७४, १; ८. ६९, १; ९७, ४; ९. ४४, ४; ८६, १४.
विवासते ८. १९, २४.
विवासते १. ११७, १.
विवासथः १. ११९, ९.
विवासंति ३. ५१, ७; ४. ११, ५; ८. ६०, ५.
विवाससि १. ७४, ९; ६. १६, १२; ९. ९८, ४; १०. ६४, ५.
विवासान् १. १७३, १.
विवासे १. ४१, ८; ६. ५१, ८^{2}; ५२, १७; ६२, ५; ६६, ११; ७. ६, २; ५८, ५; ८. १६, ३.
विवासेत् ६. १६, ४६; १०. ३१, २.
विवासेम ६. ३८, ५; ६१, २.
विवासेयं २. ३३, ६.
विविक्तः ८. १२, २४.

विविक्तः ३. ५४, ८.
विविक्तान् ३. ५७, १.
विविंचि ५. ८, ३; ८. ५०, ६.
विविक्त्रे १०. १११, ९.
विऽविंचन् १०. १२४, ५.
विविद्धि १. २७, १०; ८. ९६, १२.
विवित्से १. ३२, ४; १०. ५४, २.
विविदुत् ७. २१, ६.
विविदर्थुः ६. ७२, १.
विविदुः १. ७१, २; ७. ९०, ४; ९. ६८, ६.
विविदुषः ८. १९, १२.
विविदे १. ३९, ४.
विविदे २. १५, ९; ४. १८, १३; २६, ५; ७. ७, १; १०. ८५, ४०[2]; १३१, ३.
विविद्रिरे २. २१, ५.
विविद्रे ६. २७, १.
विविद्वान् ३. ३१, १५; ४. ५, ३.
विविप्रे ३. ३२, ४.
विविशुः ३. ७, १; ५. १९, २; १०. ५६, ४.
विविश्याः १०. १०, ३.
विविश्रे ८. १०१, १४.
विविषुः ६. ३२, ५.
विविष्टः १०. ११७, ९.
विविष्मः ६. २३, ५; ६.
विऽवृक्णा १. ३२, ५.
विऽवृत्तः १०. २७, २१.
विऽवृश्चत् ३. ३३, ७; ५. २९, ६.
विऽवृश्चन् २. १५, ६.
विवेः १. ६९, ४; १०. ७६, ३; १४७, १.
विवेक्षि ७. ३, ४.
विवेर्द ३. ३२, ४.
विवेद ३. १, ९; ३९, ५; ६; ४. ५, ९; ९. ८७, ३; ८; १०. १४, २; ६७, ५.
विवेदिथ ८. १५, ५.
विऽवेविदत् ९. ६८, ३: ८६, ९.
विवेश १ ९८, २; १६४, २१; ३२; ३. ३, ४; ७, ४; ३१, ५; ३४, ५; ६१, ७; ४. ५८, ३; ५. ४७, ३; ७. ९, ३; ८. १०१, १४; ९. ९६, २०; २२; १०. ८०, २; ८१, १; ९८, ३; ११४, ४; १२५, ६; १३०, ५.
विवेशिथ ९. २०, ५.
विवेशुः ४. २३, ९.
विवेषं ३. ३२, १४; ५. ७७, ४; १०. २७, ७.
विवेषु २. ३५, १३; ७. २१, ४.
विवेपः ७. ३७, ५.
विवेष्टि १०. ६१, १२.
विव्यक् ७. २१, ६.
विव्यक्थ ८. ९२, २३.
विव्यचंत् १०. ९६, ४.
विव्यचंत ८. ६, १५.
विव्यचुः ९. ८०, १.
विव्यथुः ६. ७२, ५.
विव्याच ३. ३६, ४; ८; ८. ८८, ५; १०. १११, २.
विव्ये ९. २२, २.
विव्ये १. १७३, ६; १०. ४९, ११.
विऽव्रंतयोः १०. १०५, ४.
विऽव्रंता १. ६३, २; ८. १२, १५; १०. ४९, २; १०५, २.
विऽव्रंतानां १०. २३, १.
विऽव्रंतेन १०. ५५, ३.
विश १. ९१, ११; १७६, १; ८. ४८, १५; ९. २, १; ८, ७; २५, २; ६३, २३; ६४, २७; ६५, २; १४; ६६, १५; ७०, ९; ७६, ३; ९६, २१; ९७, ३३; ३६; १०८, १६; १०. ८५, ४३.
विशः १. २५, १; ३१, ५; ३५, ५; ४४, ७; ५०, ५; ६९, ३[2]; ७७, ३; ९६, ३; ११४, ३; ११७, २; १२१, १; १२७, २[2]; १७२, ३; १७४, २; २. १, ८; ११, ४; २४, १०; ३. ६, ३; ४. २, ३; २४, ४; २८, ४; ५०, ८; ५. ८, २; ३; ५६, १; ६. १, ७; ८, ४; १४, २; १६, ९; २५, २; २६, १; ४७, १६; ४९, १५; ७. ५, २; ३; ६, ५; ७, ६; १०, ५; ३१, १०; ३३, ६; ६९, २; ७९, २; ८. ६, ४; २७; ११, ८; १२, २९; १३, १६; २८; ३५, १८; ६९, ३; ७५, ८; ९६, १५; ९. ७, ५; ९४, १; १०. ११, ४; ४०, ६; ४१, २; ६९, १; ९; ८०, ६; ८३, २; ९१, २; १२४, ८; १७३, १; ६.
विशः ४. ४, ३; ५. ३, ५; १८, १; ६. १५, १४; ७. ३३, १०; १०. १५२, २.
विशः १०. १४१, १.
विशःऽविंशः ६. ४९, २; ८. ७४, १.
विशत् ९. १०३, ४; १०७, १०.
विशतां १०. ३४, १४.
विशते १०. ३७, २; ८५, २९; १६८, ३.
विशंति ३. ४६, ४; ६. ३६, ३; ९. ८५, ७; ९५, ३.
विशंतु १. ५, ७; १५, १; ४. ५०, १०; १०. १८, ७; ९६, १; ९८, ४.
विशंते १०. ३७, ९.
विशं ७. ७३, ४.
विशंऽविशं ७. ७४, १; १०. ४३, ६; ८४, ४; ९१, २.
विऽशसंनं १०. ८५, ३५.
विऽशसे १०. १४३, ३.
विऽशस्ता १. १६२, १९.
विशस्व १०. ५६, १.
विशा १. ३९, ५; १११, २; २. २६, ३; ५. २६, ९; ८. २८, ३; ६३, ७; ७३, १८.
विशां १. ३६, १; ५; ४४, ९; ६५, ५; ७०, २; ९४, ५; ९६, ४; ११२, ३, १२१, ३; १२७, ८; १३४, ६; २. २, ८; ४, १; ३. २, २; १०; ११, ५; १३, ५; ३४, २; ५. १, ९; ४, ३; ९, ३; ६. २, १०; १५, १; १६, ४०; ४८, ८; ७. ७, ४; ९, २; ३९, २; ८. २३, २०; ४३, २४; ९५, ३; ९. १०८, १०; १०. २०, ४; २२, १०; ४६, ४; ६; ९२, १; १४; १५६, ६; १७३, ४.
विशि ५. २२, १; ८. २३, १३; ७१, ११.

विऽशिक्षुः २. १, १०.
विशिखाऽइव ६. ७५, १७.
विशिऽशिप्रं ५. ४५, ६.
विशे १. ९३, ८; ५. ६, ३; ४८, ४; ७. ४२, ४; ८२, १; ८. ६०, ६; ९. ८६, १५; ९७, ३०.
विशेम ८. ९६, ६.
विशेऽविशे १. २७, १०; ४. ७, १; ४; ५. ८, ५; १०. ४०, १.
विशौ ९. ७०, ४.
विश्पतिः १. २६, ७; २७, १२; ३७, ८; ६०, २; १२८, ७[2]; ७. ७, ४; ५५, ५; ८. २३, १३; २५, १६; ६०, १९; ९. १०८, १०; १०. ४, ४; १३५, १.
विश्पतिं १. १२, २; ३१, ११; १६४, १; २. १, ८; ३. २, १०; ३, ८; १३, ५; ५. ४, ३; ६. १५, ८; ८. ४४, २६; १०. ९२, १.
विश्पती इवेति विश्पतीऽइव ७. ३९, २.
विश्पते ५. ६, ५.
विश्पते ३. ४०, ३; ६. २, १०; ७. १५, ७; ८. २३, १४; १०३, ७.
विश्पत्नी ३. २९, १.
विश्पत्न्यै २. ३२, ७.
विश्पलां १. ११२, १०; ११७, ११; १०. ३९, ८.
विश्पलायाः १. ११८, ८.
विश्पलायै १. ११६, १५.
विश्पलावसू इति १. १८२, १.
विऽइर्यः १०. ९१, २.
विइर्याःऽइव १. १२६, ५.
विऽश्रयमाणः ७. ४५, ३.
विऽश्रयाते १०. ८५, ३७.
विऽश्रावि १०. ९३, १४.
विऽश्रिता १. ११७, १.
विऽश्रिताः १. ५५, २.
विऽश्रुतं १. ५२, ११.
विऽश्रुताय १. ६२, १.
विश्वऽअत् १०. १६, ६.
विश्वऽअदं ८. ४४, २६.
विश्वऽअप्सु १. १४८, १.
विश्वऽआयवे १०. २२, १४.
विश्वऽआयु १. ५७, १; ४. २८, २; ५. ५३, १३; ६. २०, ५; ७. ३४, ११.
विश्वऽआयुः १. ९, ७; २७, ३; ६७, ३; ५; ६८, ३; ७३, ४; ३. ३१, १८; ६. ४, २; १७, ९; ३३, ४; ३४, ५; ८. २, ४; ९. ८६, ४१; १०. ६, ३; ७, १; १७, ४; १०४, ९; १४४, १.
विश्वऽआयुं १. १२८, ८; १२९, ४; ९. ४, १०.
विश्वऽआयोः ४. ४२, १.
विश्वऽओजाः १०. ५५, ८.
विश्वः १. ७०, २; १२८, ६; १६६, ५; २. ३८, ८; ४. ३८, ३; ५. ३४, ७; ५०, १[2]; ७. १८, ४; ३२, १७; ५८, २; ८. ३१, १२; ५१, ९; ९. ३५, ६; १०. २८, १; ६३, १३.
विश्वकः ८. ८६, १.
विश्वऽकर्मणा १०. १७०, ४.
विश्वऽकर्मन् १०. ८१, ६.
विश्वऽकर्मन् १०. ८१, ५.
विश्वऽकर्मा ८. ९८, २; १०. ८१, २; ८२, २.
विश्वऽकर्माणं १०. ८१, ७.
विश्वऽकर्मणे १०. १६६, ४.
विश्वकाय १. ११६, २३; ११७, ७; १०. ६५, १२.
विश्वऽकृष्टयः ३. २६, ५; १०. ९२, ६.
विश्वऽकृष्टिः १. ५९, ७.
विश्वऽकृष्टिं ४. ३८, २.
विश्वऽकृष्टीः १. १६९, २.
विश्वऽगूर्तः १. ६१, ९; ८. १, २२.
विश्वऽगूर्ते ८. ७०, ३.
विश्वगूर्ती इति विश्वऽगूर्ती १. १८०, २.
विश्वऽचक्षः ९. ८६, ५.
विश्वऽचक्षसे १. ५०, २.
विश्वऽचक्षाः ७. ६३, १; १०. ८१, २.
विश्वऽचन्द्रं ९. ९३, ५.
विश्वऽचन्द्राः १. १६५, ८; ३. ३१, १६; ८. ८१, ९; १०. १३४, ३.
विश्वऽचर्षणि १०. ९३, १०.
विश्वऽचर्षणिः १. २७, ९; २. ३१, ३; ५. ६, ३; २३, ४; ६. २, २; ९. १, २; १०. ८३, ४.
विश्वऽचर्षणिं १. ६४, १४; ३. २, १५; ५. १४, ६; ६. ४४, ४; ८. ५३, ६.
विश्वऽचर्षणे १. ९, ३; ५. ३८, १; ८. २३, २; ९. ६६, १; १०. ५०, ४.
विश्वऽजन्यः १०. ६७, १.
विश्वऽजन्यं ६. ४७, २५; ७. ७६, १.
विश्वऽजन्या १. १६९, ८.
विश्वऽजन्याः ६. ३६, १; १०. २, ६.
विश्वऽजन्यां ३. ५७, ६; ७. १०, ४; १००, २.
विश्वजन्ये इति विश्वऽजन्ये ३. २५, ३.
विश्वऽजित् ८. ७९, १; ९. ५९, १; १०. १७०, ३.
विश्वऽजिते २. २१, १.
विश्वऽजिन्वा ६. ६७, ७.
विश्वऽजुवं ४. ३३, ८.
विश्वतः १. १, ४; ७, १०; १०, १२; ३१, १५; ३३, ९; ८९, १; ९१, ८; १६; ९४, ७; ९७, ५; ६; १००, १४; ११६, २०; १२२, ६; १२५, ४; १३२, ६[2]; १४४, ७; १६४, ३६; २. १, १२; १०, ५; ४३, २; ३. ३५, २; ४६, ३; ४७, २; ५१, २; ४. ९, ८; ५. ४४, ७; ४७, २; ६. १९, ९; २२, ८; ७५, १४; ७. १२, १; १५, ३; ४१, ७; ७२, ५; ८३, ८; १०४, ६; ८. ४८, १५; ६१, १६; ९८, ४; ९. ५, १; ३३, ६; ४०, ३; ४१, ६; ६१, ६; ६५, २१; ६६, ३; ६७, २५; ७४, २; ८३, १; ८६, ३८; ८९, ५; १०६, १४; १०. १९, ७; २५, ७; ३७, २; ७९, ५; ८७, २५; ९०, १; १३०, १; १३५, ३.
विश्वतःऽचक्षुः १०. ८१, ३.
विश्वतःऽधीः ८. ३४, ६.
विश्वतःऽपात् १०. ८१, ३.
विश्वतःऽबाहुः १०. ८१, ३.

विश्वतःऽमुख १. ९७, ६; ७.

विश्वतःऽमुखः १०. ८१, ३.

विश्वऽतुरा १. ४८, १६.

विश्वऽतूः ८. ९९, ५.

विश्वऽतूर्तिः २. ३, ८.

विश्वत्रं १०. ६१, २५.

विश्वऽथा १. १४१, ९; २. २४, ११; ५. ४४, १.

विश्वऽदर्शतः १. ४४, १०; ५०, ४; १४६, ५; ७. ९६, ६; ९. ६५, १३; ६६, २२; १०६, ५.

विश्वऽदर्शतं १. २५, १८; ५. ८, ३; १०. १४०, ६.

विश्वऽदानीं १. १६४, ४०; ४. ५०, ८; ६. ५२, ५.

विश्वऽदृष्टः १. १९१, ८; ९.

विश्वंऽदृष्टाः १. १९१, ५; ६.

विश्वऽदेवः ६. ६७, ६; ८. ९८, २; ९. ९२, ३; १०३, ४.

विश्वऽदेवं ५. ८२, ७.

विश्वऽदेवाः ७. ३५, ११.

विश्वऽदेवाः ६. ५१, ७.

विश्वऽदेवाय १. १४२, १२; ४. ५०, ६.

विश्वऽदेवैः १०. १२५, १.

विश्वऽदेव्य ३. ६२, ४.

विश्वऽदेव्यः १. ११०, १; १६२, ३; १०. ९२, १३.

विश्वऽदेव्यं १. १४८, १; ३. २, ५.

विश्वदेव्यऽवता १०. १७०, ४.

विश्वऽदोहसः १. १३०, ५[२].

विश्वऽदोहसं ६. ४८, १३.

विश्वधं १. ६३, ८; १७४, १०; ४. १९, ६.

विश्वधा १. १४१, ६; ४. १६, १८; ५. ८, ४; ७. २२, ७; ८. ५, १; ९. ७९, २.

विश्वऽधायुः १०. ८३, ६.

विश्वऽधायसः १०. १२२, १; १७६, १.

विश्वऽधायसं २. १७, ५; ५. ८, १; ७. ४, ५; ८. ५, १५; ७, १३; १०. १२२, ६.

विश्वऽधायाः १. ७३, ३; ३. ५५, २१.

विश्वऽधेनाः ४. १९, २.

विश्वऽधेनां ४. १९, ६.

विश्वऽपिशः ७. ५७, ३.

विश्वऽपिशा ७. ७५, ६.

विश्वऽपुर्ष १. १६२, २२.

विश्वऽपुषा ८. २६, ७.

विश्वऽपेशसं १. ६१, १६.

विश्वऽपेशसा १. ४८, १६; ४. ४८, ३.

विश्वऽप्सुं ६. ३५, ३.

विश्वऽप्सुः १०. ७७, ४.

विश्वऽप्सुं ८. २२, १२.

विश्वऽप्स्न्यः ७. ७१, ४.

विश्वऽप्स्न्यस्य ७. ४२, ६; ८. ९७, १५.

विश्वऽप्स्न्याय २. १३, २.

विश्वऽभरसं ४. १, १९.

विश्वऽभानुषु ४. १, ३; ८. २७, ३.

विश्वऽभुवे १०. ५०, १.

विश्वऽभेषजः १०. ६०, १२; १३७, ३.

विश्वऽभेषजीः १. २३, २०.

विश्वऽभोजसं ६. ४८, १३.

विश्वऽभोजसा ७. १६, २.

विश्वऽभोजाः ५. ४१, ४.

विश्वऽभ्राट् १०. १७०, ३.

विश्वं १. १६, ८; ३१, ९; ३६, ४; ६; १४; २०; ३७, १५; ३८, १०; ४१, ६; ४८, ८; ४९, ४; ५०, ४; ५; ५२, १३; १४; ५७, २; ६; ७३, ५; ८; ८१, ५; ९; ८५, ३; ८६, १०; ९२, ९; ९३, ३; ९८, १; १०२, ८; १०८, २; ११४, १; १२९, ४; १३०, ८; १६४, ४२; ४४; १८५, १; १८६, १; ९; २. २, ५; ५, २; १५, ४; २२, ४; २३, १९; २४, १२; १६; ३३, १०; ३५, १५; ३८, ५; ४०, ५; ३. ४, ५; २९, १५; ३०, ६; १४; ४४, ४; ५४, ८; ५५, ८; ४. १, १; ५, ११; ६, १; १७, १०; ५४, ४; ५८, ११; ५. ६, ६; २८, २; ३२, १०; ४१, ७; ४८, २; ५०, ३; ६३, ७; ८१, ५; ८३, २; ९; ६. ८, ३; १३, ४; १६, २७; २८; २०, २; १३; २५, ८; ३१, २; ५२, १५; ६०, ४; ७. ७, २; ६; १६, ६; २०, ३; ५६, २०; ५९, ७; ६६, १५; ७६, १; ७७, १–३; ९०, ६; ९८, ६; ८. ३, १६; २०, २६; २४, २१; २६, ६; ३१, ८; ३९, ७; ४०, ४; ४१, ३; ४७, १३; ४९, ८; ५८, २; ७८, ५; ७९, २; ८९, ६; ९. ६१, १८; ६३, ५; ६८, ९; ८६, २८; १०. २, ४; ११, १; १७, १; १०; २०, १०; २२, ११; २७, २२; ३५, १३; ३६, ४; ३७, २; ४; ५६, ५; ५८, १०; ६१, १२; ६४, १५; ८३, १; ८५, ४२; ८८, १५; ९२, ५; ९६, ५; १०७, १; ८; ११४, ४; १२१, ७; १२६, ४; १३३, २; १३६, १; १७३, ४.

विश्वऽमनः ८. २३, २.

विश्वऽमनसः ८. २४, ७.

विश्वऽमनाः १०. ५५, ८.

विश्वऽमनुषां ८. ४६, १७.

विश्वऽमहसः १०. ९३, ३.

विश्वऽमानुषः ८. ४५, ४२.

विश्वंऽइन्व ३. २०, ३; ७. २८, १.

विश्वंऽइन्वः २. ४०, ६.

विश्वंऽइन्वं १. ६१, ४.

विश्वंऽइन्वा ५. ८०, २.

विश्वंऽइन्वाः १०. ११०, ५.

विश्वमिन्वे इति विश्वंऽइन्वे १. ७६, २; ३. ३८, ८; ९. ८१, ५; १०. ६७, ११.

विश्वंऽइन्वेभिः ५. ६०, ८.

विश्वंऽएजय ९. ३५, २; ६२, २६.

विऽश्वयत् ७. ५०, १.

विश्वया ८. १, १९; ६८, २.

विश्वऽरूपः १. १६२, २; ३. ३८, ४; ५५, १९; ५६, ३; ६. ४१, ३; १०. १०, ५.

विश्वऽरूपं १. १३, १०; ३५, ४; २. ११, १९; ३३, १०; ३. ६२, ६; १०. ६७, १०; ८५, २०.

विश्वऽरूपस्य १०. ८, ९.

विश्वऽरूपाः ३. १, ७; ५. ८३, ५; ८. १००, ११; १०. ७८, ५; ८८, १०.

विश्वऽरूपां १. १६१, ६; ४. ३३, ८

विश्वऽरूपेभिः १०. ७०, २.

विश्वऽरूप्यं १. १६४, ९.

विश्वऽवसुः १०. १३९, ५.

विश्वऽवसुं १०. ८५, २१; १३९, ४.

विश्ववसो इति विश्वऽवसो १०. ८५, २२.

विश्वऽवार १. ३०, १०; **७.** ५, ८; १६, ५; ९२, १; **८.** ४६, ९; **९.** ९१, ५.

विश्वऽवारः ३. १७, १; **७.** ९७, ४; **९.** ८८, ३; **१०.** १४९, ४.

विश्वऽवारं १. ४८, १३; **५.** ४, ७; **६.** ३७, १; ४९, ४; **७.** ७, ५; १०, ४; ८४, ४; **८.** ७१, ३; **१०.** १५०, ३.

विश्वऽवारस्य ३. ३६, १०; **५.** ४४, ११; **६.** २३, १०.

विश्वऽवारा ३. ४, ३; **५.** २८, १; ८०, ३.

विश्वऽवारा ७. ७०, १.

विश्वऽवाराः १. १२३, १२; **७.** ९१, ६; **९.** ९७, २६.

विश्वऽवाराणि ६. ५, १.

विश्वऽवाराभिः ६. २२, ११.

विश्वऽवारे १. ११३, १९; **३.** ६१, १; **७.** ७७, ५.

विश्ववारे इति विश्वऽवारे ७. ७, ३.

विश्वऽवार्यः ८. १९, ११.

विश्वऽवार्ये ८. २२, १२.

विश्वऽवित् ९. २७, ३; २८, १; ५; ८६, २९; ३९; ९७, ५६; **१०.** ९१, ३.

विश्वऽवित् ९. ६४, ७.

विश्वऽविदं १. १६४, १०; **३.** १९, १; २९, ७; **५.** ४, ३.

विश्वऽविदा ६. ७०, ६.

विश्वऽवेदसः १. ६४, ८; १०; **३.** २६, ४; **५.** ६७, ३; **८.** २७, ४; **१०.** ६६, १; ५.

विश्वऽवेदसः ५. ६०, ७; **८.** १८, ११; २७, २; ४; ११; १९–२१; ४७, ३; **१०.** ९३, ७.

विश्वऽवेदसं १. १२, १; ३६, ३; ४४, ७; १२८, ८; १४३, ४; **४.** ८, १.

विश्वऽवेदसा १०. १४३, ६.

विश्वऽवेदसा ८. २५, ३.

विश्वऽवेदसा १. ४७, ४; १३९, ३.

विश्वऽवेदाः १. ८९, ६; ९१, २; १४७, ३; **३.** २०, ४; २५, १; **६.** ४७, १२; **८.** ४२, १.

विश्वऽव्यचसं ३. ४६, ४.

विश्वऽशंभुवं १. २३, २०.

विश्वऽशंभुवा १. १६०, १; ४; **६.** ७०, ६.

विश्वऽशंभूः १०. ८१, ७.

विश्वऽशर्धसो ५. ३४, ८.

विश्वऽश्चुचे ७. १३, १.

विश्वऽश्नुष्टिः १. १२८, १.

विश्वऽसहं ३. ४७,५; **६.** ४४, ४; **८.** ९२, १.

विश्वऽसामन् ५. २२, १.

विश्वऽसुविदं १. ४८, २.

विश्वऽसौभग १. ४२, ६.

विश्वऽसौभगः १. १५७, ३.

विश्वस्मात् १. १०६, १–६; १२३, २; १३४, ५; **२.** १७, ६; **४.** २, ६; २८, ४; **८.** ६०, १०; **१०.** ३६, ३; ८६, १.

विश्वस्मिन् १०. ४९, १; ५०, ४.

विश्वस्मै १. ३०, २; ५५, ३; ६६, ३; ९२, ४; १२८, ६[२]; **५.** ८३, ४; **६.** १, १; **७.** ६६, १४; **९.** ४८, ४; **१०.** ८८, १२.

विश्वस्य १. ११, ४; २५, २०; ४४, ५; ४८, १०; ९२, ९; १००, ७; १०१, ५; ११३, ७; १२८, १; १६४, २१; १६५, ६; **२.** १२, ९; १३, ६; २७, ४; ३८, २; ४०, १; **३.** १४, ७; ४६, २; **४.** १३, ३; **५.** ७, ६; ३२, ७; ३४, ६; ४२, ११; ५५, ८; ७१, २; ८५, ३; **६.** १६, १३; ३६, ४; ४२, ३; ५०, ७; ५१, ७; ६१, ३; ७१, २; **७.** ११, ४; १६, १; ३२, १६; १७; ६०, २; ६५, १; १०१, २; १०४, १६; **८.** १७, ९; २५, १; ४७, ४; ६२, ७; **९.** ३२, ३; ६६, २; ७६, ४; ८६, ५; २८; ३६; ८८, ४; ९७, ५६; १०१, ५; ७; **१०.** ५, ३; २६, ८; ३७, ५; ४५, ६; ६३, ८; ८७, १५; ९१, १; १०२, १२; १६०, २; १६१, ३; १६८, २; १९०, २.

विश्वस्याः ८. ७१, १; **१०.** ६, ३.

विश्वस्यै ८. ३९, ४.

विश्वहं २. १२, १५; **७.** २१, ९; **८.** ४८, १४.

विश्वहा १. १११, ३; १६०, ५; **२.** २४, १५; ३२, ३; ३५, १४; **४.** ३१, १२; **६.** १, ३; ४७, १५; **८.** ४३, २६; ४४, २२; **१०.** ७८, ६; ८८, १४; ९१, ६; १००, ४.

विश्वा १. ३५, ३; ५; ३६, ५; ४०, ६; ५१, ७; ८; १३; ५२, ११; ६३, १; ६४, ३; ७२, १; ९; ७३, २; ८४, २०; ८५, ८; ९१, १९; ९२, ३; १५; ९४, ६; ९५, १०; ९६, १; ९९, १; १०१, ६; १०८, १३; १०९, ६; ११३, ४–६; १२८, ४; १३०, ६; ७; ९; १३१, १; ७; १३४, ४; १४६, १; १४९, ४; ५; १५२, १; १५४, २; ४; १६४, २; १३; १४; ४९; १६६, ४; १७१, ३; १७३, ८; १७८, १; १८९, २; **२.** १०, ४; १२, ४; १३, १०; ११; १७, १; ४; १८, ७; २४, ११; ३४, ४; ४१, १७; **३.** ३, १०; १६, ४; २०, ४; ३१, ८; ५४, ८; २२; ५५, १०; १९; ६१, ३; ६२, ९; **४.** १, ४; ८; ३, १६; ४, ७; ६, ५; १६, ५; २२, ४; ६; २७, १; ३०, २; ३६, ८; ४२, ३; ६; ७; ५०, ७; **५.** १६, ३; २९, १४; ३१, ३; ५७, ६; ७३, ४; ७७, ३; ८१, २; ८२, ६; ९; **६.** १, ९; ५, २; ७, ६; ७; १३, १; १५, १०; १३; १६, २०; १७, १; १३; १९, ६; २५, ५; ३१, २; ४६, ६; ६०, १०; ६४, १; ६९, ४; ७२, १; ७४, ३; ७५, १४; **७.** ३,

१०; १२, २; १६, ४; १७, ५; १८, १; १३; १४; १७; २१, ३; ४; २२, ७; २५, ४; ३२, १५; ४४, ३; ५५, १; ६१, १; ५; ६२, १; ६; ७८, २; ८०, १; ८२, ५; ८७, २; ९१, ३; **८.** १, ३; २, ३४; ३, ६; १२, २१; २८; १४, ६; १५, १०; १३; १९, १४; २२, १८; २३, १३; ३१, ३; ३५, ४; ४१, ७; ४२, १²; ३; ४३, ३०; ४६, १२; ५१, ४; ५३, ४; ६१, १७; ६२, २; ७०, ६; ७५, २; ७७, १०; ७८, ८; ८८, ४; ९२, ६; १३; ९३, २७; ९४, ९; ९६, ६; ९७, ९; १३; ९९, ३; १००, ४; १०३, ५; ६; **९.** १, १०; ४, २; २५, ४; २८, २; ५; २९, ४; ३६, ५; ४०, ४; ५५, १; ५७, २; ४; ६४, ६; ८; १८; ६५, २; ९; १०; ७३, ८; ८०, ३; ८५, १२; ८६, ५; ३०; ८७, ६; ८८, २; ९०, १; ६; ९४, ३; ९७, ५१; १०२, १; १०८, ११; १०९, ४; ११०, ९; १११, १²; **१०.** १, १; ६, ६; २०, ८; २१, ६; २५, ६; ३१, १; ३७, ९; ३९, ४; ४४, १; ४५ ११; ४९, ११; ५०, ५; ६; ५४, ५; ५६, ५; ७; ६३, २; ६५, १५; ८१, १; ८२, ३; ८३, ३; ८८, ९; ११; १६; ९०, ३; ९६, ८; १००, ९; ११०, ९; १११, ५; ११३, १०; १२५, ७; ८; १३६, ४; १३७, ५; १३९, १; ३; १४२, २; १५३, ५; १६५, ५; १६९, ३; १७०, ४; १७४, ३.

विश्वाऽइव **१.** १३०, २; ९.

विश्वाः **१.** ३, १२; ११, १; ५४, १०; ७१, ७; ८६, ५; ९१, २२; ९८, २; ११७, २३; १३४, ६; १३९, ३; १७९, ३; **२.** ७, ३; ८, ५; ११, १९; १३, ३; २३, ५; १३; ३३, ३; ४०, ५; **३.** ११, ६; १५, ४; ३१, १३; २१; ४४, २; ४९, १; **४.** ७, ४; १७, ६; ७; २२, १०; ३१, १०; ३७, ७; ४०, १; **५.** ४, ५; १०, ६; २३, १; २५, ९; ३०, ५; ५५, ६; ६२, २; ७५, २; **६.** १८, ५; २२, ९; २५, २; ४१, ४; ५१, १६; ५८, १; ६०, ६; ६१, ९; **७.** १, ७; १०; १९, १; २९, ३; ६७, ५; ७२, १; ९५, १; १०४, ११; **८.** २, ३३; ६, ४; ११, ८; १३, २१; १४, १३; १६, ११; २४, १९; २६; ३६, १; ३९, २; ४३, १८; २९; ४५, ८; ४०; ४६, ७; ६९, १४; ८४, ६; ९२, २०; ९६, ७; ९७, १०; ९९, ५; ६; १०२, ९; **९.** ८, ७; १३, ८; १६, ६; २०, १; ४०, १; ४३, २; ६१, २८; ६२, १९; २४; ६३, २६; २८; ८६, १५; ४१; ८९, ६; **१०.** १८, ९; २१, ३; ३५, ८; ४३, १; ५१, १; २; ६७, ११; ९७, १०; १२७, १; १३३, ३; १५३, ५.

विश्वाची **७.** ४३, ३.

विश्वाचीः **१०.** १३९, २.

विश्वाच्या **९.** १०१, ३.

विश्वात् **१.** १८९, ६.

विश्वान् **१.** १४, ९; २३, १०; ४८, १२; ७६, ३; १४६, ३; १८८, ९; **२.** ३७, ६; **३.** ६, ६; ९, ६; ५४, २२; ५७, ५; ५९, ८; **४.** ३०, ५; ४५, ६; **५.** १, ८; ४३, १०; **६.** ५१, ९; **७.** ९, ५; ४८, ३; **८.** १०, २; २३, २६; ६५, ९; ६६, १०; **९.** ५९, ४; ८०, ४; ८६, ४८; ९८, ७; **१०.** ६०, ६; ६६, १३; ८९, १६; १३०, ५; १३१, १.

विश्वानरः **१.** १८६, १; **७.** ७६, १.

विश्वानरस्य **८.** ६८, ४.

विश्वानराय **१०.** ५०, १.

विश्वानि **१.** ५, ९; ९, २; २३, २०; २५, ११; ३८, ३; ५१, ७; ६७, २; ६९, ३; ७०, १; ४; ९२, ९; १०८, १; १२९, ५; १४५, ३; १४८, २; १६६, ९; १७६, ३; १८९, १; १९१, ९; **२.** १, ८; ३, १; ४, २; ५, ३; १६, २; २८, १; ३५, २; ४०, ५; **३.** १, १६–१८; ५, ६; ११, ८; ९; ३८, ६; **४.** ४, ६; १६, ६; ३०, २२; ३९, १; **५.** २, ९; ३, ११; ४, ७; ९; १८, १; ४२, १८; ४५, ७; ८२, ५; **६.** १५, १५; २२, ७; ४२, १; ४५, ८; २०; ४६, ७; ५१, १०; **७.** ४, १; १८, १५; २३, १; ६०, १२; ६६, १०; १०१, ४; **८.** १, ३२; ५, ८; ८, १०; १३; १६, २; १८, १७; २४, ७; ३२, २८; ४१, ६; ४७, ३; ६३, ६; ९३, २९; ९७, १४; **९.** ३, ४; १४, ८; १८, ४; २०, ३; २१, ४; २३, १; ४२, ५; ५४, ३; ५९, ३; ६१, ११; ६२, १; २५; ६३, २५; ३०; ६६, १; ४; ८४, २; ८६, २६; ९४, ५; १००, २; ८; १०७, २३; १०९, ८; ९; १४; **१०.** २१, ५; ५४, ४; ५९, २; ६३, १३; ८१, ७; ८२, ६; ८५, १८; ८९, ५; १२२, २; १२६, ६; १३४, ४; १६४, ३; १९१, १.

विश्वाभिः **१.** १२, १२; २३, ६; १००, १०; **२.** १०, २; **३.** ३७, ३; **४.** ३१, १२; **६.** १३, ६; ५९, १०; **७.** १९, ३; २४, ४; **८.** ८, १; १८; १२, ५; ३२, १२; ३५, २; ३७, १; ६१, ५; १०१, १६; **९.** ८६, २४; **१०.** ९२, १४; १०४, ३; १३४, ३.

विश्वा **३.** ३१, ५; **४.** ११, ६; **१०.** ३७, ४; ४२, १०; ६३, १२.

विश्वामित्रः **३.** ५३, ९.

विश्वामित्रजमदग्नी इति **१०.** १६७, ४.

विश्वामित्रस्य **३.** ५३, १२.

विश्वामित्राः **३.** ५३, १३; **१०.** ८९, १७.

विश्वामित्राय **३.** ५३, ७.

विश्वामित्रेभिः **३.** १, २१.

वि॒श्वामि॑त्रेषु ३. १८, ४.

विश्वा॑य १. ५०, १.

वि॒श्वायु॑ऽपोपसं १. ७९, ९; ६. ५९, ९.

वि॒श्वायु॑ऽवेपसं ८. ४३, २५.

विश्वा॑सां १. १२७, ८; १७४, १०; ५. ४४, १३; ६. १५, १; २०, ३; ४८, ८; ६९, २; ८. ७०, १.

विश्वा॑सु १. ७९, ७; ८; १२२, १०; १२७, १०; ४. १, १८; ५. १७, ४; ६४, २; ७. ३४, १२; ८. २०, २०; ७१, १५; ९०, १; ९२, ७; १८; ९५, २; १०. ५०, २; १४७, २.

वि॒श्वाहा॑ १. २५, १२; ९०, २; १००, १९; १०२, ११; १६०, ३; ३. १६, २; ४. ४२, १०; ६. ४७, १९; ७५, ८; १७; ७. ९८, १; १०. १८, १२; ३७, २^{२}; ७; ५३, ११.

विश्वे॑ १. ३, ७–९; १९, ३; २३, ८; ३४, २; ४३, ३; ५२, १५; ५९, १; ६५, १; ६८, २^{२}; ३; ६९, ५; ७०, ५; ७२, २; ८९, ७; १०; १०३, ७; ११६, १७; १२२, ३; १२; १४; १२७, ६; ८; १३१, १; १३६, ४; १६४, २२; ३९; १८६, २^{२}; २. १, १४; ३, ४; १२, ७; १६, ४; २४, ४; २५, ५; ४१, १३; १५; ३. १४, ४; ३०, १३; ३२, ८; ३८, ४; ९; ५१, ८; ५४, १७; ५७, २; ५८, ४; ४. १, १०; १८; १६, १९; १७, ५; ६; १८, १; १९, १; ३०, ३; ३४, ३; ४२, १; ५. ३, १; २१, ३; २३, ३; २९, ५; ८; ३१, १०; ३६, २; ४३, १०^{२}; ४५, ८; ५१, १३; ५२, ४; ५८, ३; ६७, ३; ६. ७, ४; ९, ५; ७; १६, ८; १७, ८; ११; १८, १४; ४५, ३३; ५०, १४; १५; ५१, ५; ५२, ८; १०; १३; १४; १७; ५८, २; ६७, ५; ६८, ४; ७. ६, ६; २८, १; ३३, ११; ३४, २४; ३८, ३; ३९, ४; ४४, ५; ४८, ४; ४९, ४; ५०, ३; ५१, ३^{४}; ५२, ३; ५७, ७; ५९, ३; ७८, ४; ८२, २; ८. ४, ५; ६, ३१; २३, १८; २७, २; ४; ५; १४; ३०, १; ४; ४१, ७; ४६, १२; ४८, १; ५३, ४; ५४, ३; ६२, ७; ६९, ११; ९३, १४; ९४, २; ९६, ७; १००, १; ९. ५, ११; १४, ३; १८, ३; ६७, २७; ८१, ५; ९२, ४; ५; ९६, ४; १०२, ५; १०९, २; १५; १०. १२, ३; १३, १; १५, ६; २४, ५; २७, ४; ३३, १; ३५, १३^{४}; ३६, १३; ५२, १; २; ६३, ६; ११; १७; ६४, ६; ६५, १३; १४; ६६, ११; ७०, ११; ८२, ५; ६; ८५, १४; ४७; ८८, ७; ९३, ३^{२}; ७; ९८, ९; ११२, ६; ११३, ३; ८; १२०, १; ३; १२१, २; १२८, ४; ५; १३०, ३; १४२, ६; १५७, १.

विश्वे॒ इति॑ ४. ५६, ४.

विश्वे॑न १. ५०, १३.

विश्वे॑भिः १. ९, १; १४, १; १०; २६, १०; ९१, १७; ९५, ९; १८९, ३; २. ३७, ६; ३. २४, ४; ४०, ३; ४. १०, ३; ११, २; ५. २६, ४; ४३, १३; ५१, ८; ६. १२, ६; १५, १६; २१, ११; ७. ८, ५; ११, १; ३८, ३; ५७, ६; ८. २१, ४; ७१, ३; ९२, २९; ९. ६७, २८; १०. ३१, १; ९८, ८; ११३, १.

विश्वे॑भ्यः २. ५, ८; २३, १७.

विश्वे॑षां १. ५८, ७; ६८, १; २. २३, २; २७, १०; ३८, ६; ४. १, २०^{२}; ७, ३; ९, २; ६. १६, १; ६७, १; ७. ५, १; ८. १, २१; ३, २१; १९, ३४; ४६, १६; ५३, ३; १०२, १०; १०. २, ६; ९३, ३.

विश्वे॑षु १. १३०, ८; १३१, २; १५७, ५; ४. २२, ५; ७. ३०, २; ८. ३९, ८; ९. ९२, ३; १०. २५, २; २८, २; ५०, ४; १८३, ३.

विश्वैः॑ १. ९१, ४; ३. ५४, १५; ५. ५१, १; ८. ३५, ३; १०. १६९, ४.

विश्व्या॑ २. ४२, १.

विषः॑ ८. १९, ११; १०. १०९, ५.

वि॒षं १. १९१, १०; ११; १४–१६^{२}; ६. ६१, ३; ७. ५०, ३; १०. ८७, १८; १३६, १.

वि॒षऽवं॑त् १०. ८५, ३४.

वि॒षस्य॑ १. १९१, १२; १३; १०. १३६, ७.

वि॒षा॒णिनः॑ ७. १८, ७.

विषु॑णः ५. ३४, ६; ८. २९, १.

वि॒षु॒णक् १. ३३, ४.

विषु॑णं ३. ५४, ८.

विषु॑णस्य ४. ६, ६; ७. २१, ५.

विषु॑णाः ५. १२, ५.

विषु॑णे ८. ९६, १४.

वि॒षु॒द्रुहा॑ऽइव ८. २६, १५.

विषु॑ऽरूपः ५. १५, ४.

विषु॑ऽरूपं ७. २७, ३.

विषु॑ऽरूपा ७. ८४, १; १०. १०, २.

विषु॑ऽरूपाणि ६. ७०, ३.

विषु॑ऽरूपे १. १८६, ४.

विषु॑रूपे॒ इति॑ विषु॑ऽरूपे १. १२३, ७; ६. ५८, १.

विषु॑ऽरूपेषु १०. ६४, ५.

वि॒षु॒ऽवतः॑ १. ८४, १०.

वि॒षु॒ऽवता॑ १. १६४, ४३.

वि॒षु॒ऽवृत् १०. ४३, ३.

वि॒षु॒ऽवृतं॑ २. ४०, ३.

विषू॑चः ६. ५९, ५; ७. ८५, २; १०. ७६, ७.

विषू॑ची ३. ५५, १५.

विषू॑चीः १. १६४, ३१; २. ३२, २; ६. २५, २; ३०, ५.

वि॒षू॒चीना॑ १. १६४, ३८.

विषू॑चीं ६. ७४, २; ८. १४, १५.

विषू॑चोः ७. १८, ६.

वि॒षेणं॑ १. ११७, १६; १०. ८७, २३.

वि॒ष्टऽअं॑ता १०. ९३, १३.

वि॒ष्टः १. १४७, ·१.

वि॒ष्टपः॑ ८. ३४, १३.

विष्टपं ८. ३२, ३; ६९, ८; ९. ३४, ५; ४१, ६; ११३, १०.
विष्टपा ८. ९१, ५.
विष्टपि १. ४६, ३; ८. ९७, ५; ९. १२, ६; १०७, १४; १०. १२३, २.
विष्टं ३. ३०, ६.
विष्टंभः ९. २, ५; ८६, ३५; ८७, २; ८९, ६; १०८, १६.
विष्टिऽभिः १. ९२, ३.
विष्टी १. २०, ४.
विष्ट्वी १. ११०, ४; ३. ६०, ३; १०. ९४, २.
विष्णावि ८. ३, ८; १२, १६.
विष्णवे १. १५४, ३; १५५, १; १५६, २; ४. ३, ७; ५. ८७, १; ७. १००, १; ८. २५, १२; ९. ३३, ३; ३४, २; ५६, ४; ६३, ३; ६५, २०; १००, ६.
विष्णाप्वं १. ११६, २३; ११७, ७; १०. ६५, १२.
विष्णाप्वे ८. ८६, ३.
विष्णुः १. २२, १६–१८; ६१, ७; ८५, ७; ९०, ९; १५४, २; १५६, ४; ५; १८६, १०; २. १, ३; ३. ५५, १०; ५. ४६, ४; ४९, ३; ६. १७, ११; ४९, १३; ५०, १२; ७. ३५, ९; ९३, ८; १००, ३; ४; ८. १२, २७; १५, ९; २५, १४; ५२, ३; ५४, ४; ७७, १०; १०. १, ३; ६५, १; ६६, ५; ९२, ११; ११३, २; १२८, २; १८४, १.
विष्णुना २. २२, १; ५. ५१, ९; ६. २०, २; ८. ३५, १.
विष्णुं ३. ५४, १४; ५. ४६, ३; ६. २१, ९; ४८, १४; ७. ३६, ९; ३९, ५; ४४, १; ९. ९०, ५; १०. १४१, ३; ५.
विष्णुऽवंता ८. ३५, १४.
विष्णो इति १. ९०, ५; ७. ९९, १; ८. २७, ८; ८३, ७.
विष्णो इति १. १५६, १; ३; ४. १८, ११; ५. ४६, २; ६. ६९, ८; ७. ९९; २; ३; ६; ७; १००, २; ६.
विष्णोः १. २२, १९–२१; १५४, १; ५; १६४, ३६; २. ३४, ११; ५. ३, ३; ८७, ८; ७. ४०, ५; ८. ९, १२; २०, ३; ३१, १०; ९. ९६, ५; १०. १५, ३; १८१, १.
विष्पट् १. १८९, ६.
विष्पितस्य ७. ६०, ७.
विष्पिता ८. ८३, ३.
विष्पुलिंगकाः १. १९१, १२.
विष्वंक् १. ३६, १६; १४६, ३; ४. ४, २; १२, ४; ६. ६, ३; ७. ३४, १३; ४३, १; ८. ४५, ८; ६७, २१; ९. ९७, १६; १०. ३६, ९; ३८, १; ८९, ४; १३४, ५.
विष्वंङ् १०. ९०, ४.
विष्वंचः १०. २७, १८.
विष्वंचं ९. ७५, १.
विष्वद्र्यंक् ७. २५, १.
विष्वाचः १. ११७, १६.
विऽसंक्तां १. ११७, २०.
विऽसंदृशा १. ११३, ६.
विऽसर्गे ७. १०३, ९.
विऽसर्गे १०. ५, ६.
विऽसर्जने ५. ५९, ३; ८. ७२, ११.
विऽसर्जनेन १०. १२९, ६.
विऽसर्माणं ५. ४२, ९.
विऽससहिः १०. १५९, १; १७४, ५.
विऽससहिं १०. १६६, १.
विऽसह्यं ७. २१, ७.
विऽस्याने ५. ४४, ११.
विऽसारे १. ७९, १.
विऽसितः ६. १२, ५; १०. २७, १४.
विऽसितं ५. ८३, ७.
विसितऽस्तुका १. १६७, ५.
विऽसिताः ५. ८३, ८.
विऽसितासः ६. ६, ४.
विसिते इति विऽसिते ३. ३३, १.
विऽसृजंतः १०. ६५, ११.
विऽसृतः ४. १९, ५.
विसृष्टऽधेना ७. २४, २.
विसृष्टऽरातिः १. १२२, १०.
विऽसृष्टाः ८. १००, १२.
विऽसृष्टिः १०. १२९, ६; ७.
विस्कंभिते इति विऽस्कंभिते ६. ७०, १.
विऽस्कंभे ८. १००, १२.
विऽस्कभ्नंतः ३. ३१, १२.
विऽस्तारः ५. ५२, १०.
विऽस्तिरः १. १४७, ७; २. ३३, १०.
विऽस्थाः १०. १६८, २.
विऽस्थितः २. ३८, ६.
विऽस्थितं ६. ४७, २९; १०. २५, ६; ११४, ८.
विऽस्थिता १. १६३, ११.
विऽस्थिताः १. १८७, ४; १०. ९७, १९.
विऽस्पर्धसः १. १७३, १०; ५. ८७, ४; ८. २३, २.
विस्फुरंती इति विऽस्फुरंती ६. ७५, ४.
विऽस्यन् ५. ४५, १.
विऽस्रसः २. ३९, ४; ८. ४८, ५.
विऽस्रुहः ६. ७, ६.
विऽस्रुहा ५. ४४, ३.
विऽहत्य ५. ४, ५.
विऽहंता १. १७३, ५.
विऽहरति १०. १६२, ४.
विऽहरन् ४. १३, ४.
विऽहरंते ७. १०४. ९.
विऽहवंत ७. २८, १.
विऽहवे ३. ८, १०; १०. १२८, २.
विऽहवेषु १०. १२८, १.
विऽहव्यः १. १०८, ६; २. १८, ७.
विऽहायसः ९. ७५, ५.
विऽहायसं ८. २३, १९.
विऽहायसे ८. २३, २४.
विऽहायाः १. १२३, १; १२८, ६; ३. ३६, २; ४. ११, ४; ६. १३, ६; ८. ४८, ११; १०. ८२, २; ९२, १५.
विहि ४. ४८, १.
विहि २. २६, २; ३. २१, ५.
विऽहितानि १. १६४, १५.
विहुत्मतीनां १. १३४, ६.
विऽह्रुतं ८. १, १२; २०, २६.
विऽह्वयंते ८. ५, १६; ४०, ७.
विऽह्वयामहे १. २६, १३.
विह्वयेते इति विऽह्वयेते २. १२, ८.
वीः १. १२३, ६.

वीच्यां १०. १०, ६.
वीतऽस्तंमानि ७. १, १८.
वीतऽपृंष्ठः १. १६२, ७.
वीतऽपृंष्ठा ३. ३५, ५.
वीतऽपृंष्ठाः १. १८१, २; ५. ४५, १०; ८. ६, ४२.
वीतं १. ९३, ७; १५३, ४; १६२, १५; ३. ५३, १; ४. ७, ६; ६. ६०, १५; ७. ६८, १; १०. ६१, ४.
वीतयें १. ५, ५; १३, २; ७४, ४; ६; १३५, १; ३^२; ४^२; १४२, १३; २. २, ६; ३. १३, ४; ५. २६, २; ५१, ५; ५९, ८; ६. १६, १०; ४४; ५३, १०; ७. १६, ४; ५७, २; ६८, २; ८. २०, १०; १६; ६०, ४; ९३, २२; १०१, ७; १०; ९. ६, ९; ६२, २३; १०४, ३; १०५, ३.
वीतऽवारासः ८. ४६, २३.
वीतऽहृंव्यं ७. १९, ३.
वीतऽहृंव्याय ६. १५, ३.
वीतऽहृंव्ये ६. १५, २.
वीता ४. २, ११; ९. ९७, १७.
वीतात् १०. ११, ८.
वीतिं ९. १, ४; ९७, २५.
वीतिऽराधसं ९. ६२, २९.
वीतिऽहोत्राः १. ८४, १८; ३. २४, २.
वीतिऽहोत्रं २. ३८, १; ५. २६, ३.
वीतिऽहोत्रा ८. ३१, ९.
वीती ६. ६, १; १६, ४६; ८. ५४, ६; ९. ९, २; ६१, १; ९१, २; ९७, ४९.
वीते ९. ८२, ३.
वीयः १. १५१, ७; ७. ८२, ७.
वीयः १. १५१, ३.
वीनां १. २५, ७.
वीर १. ३०, ५; ८१, २; २. १३, ११; २६, २; ६. २१, १; ६; ८; ४४, १३; ४५, १३; २६; ६३, १०; ७. २९, २; ८. २३, १४; ९. ११०, ७; १०. ९५, ५.
वीरः १. १८, ४; २. ३, ९; १४, १; ३३, १; ४२, २; ३. ४, ९; ५५, २०; ४. १५, ५; २३, २; २४, १; २५, ६; ५. ३०, १; ६. २४, २; ४७, १६; ७. १, २१; २०, २; ३२, ६; ५६, २४; ८. २३, १९; २४, १६; ३३, १६; ९. १०१, १५; १०. २८, १२; १०३, ७; १११, १; ११३, ४.
वीरकः ८. ९१, २.
वीरऽकर्म १०. ६१, ५.
वीरऽकुक्षिं १०. ८०, १.
वीरऽजातं १०. ३६, ११.
वीरऽतमाय ३. ५२, ८.
वीरऽतरः ८. २४, १५.
वीरऽपत्नी १. १०४, ४; ६. ४९, ७.
वीरऽपस्त्यः ५. ५०, ४.
वीरऽपेशाः ४. ११, ३; १०. ८०, ४.
वीरं १. ४०, ३; ६१, ५; ९१, २०; ११८, २; २. ३२, ४; ३. ५१, ४; ६. १४, ४; २३, ४; ५०, ६; ५३, २; ७. ३४, ६; ३६, ८; ९२, ३; ८. ४६, १४; ४९, ६; ५०, ६; ८६, ४; ९८, १०; १०३, ४; ९. ९७, ४४; १०. ७३, १; ८०, १.
वीरयध्वं १०. १०३, ६; १२८, ५.
वीरऽया ७. ९०, १; ९. ६४, ४.
वीरऽयुः ८. ९२, २८; ९. ३६, ६.
वीरऽवः ९. ३५, ३.
वीरऽवक्षणं ५. ४८, २.
वीरऽवत् १. १९०, ८; ४. ३२, १२; ३६, ९; ५. ७९, ६; ६. ६५, ३; ७. १५, १२; ७५, ८; ८. २३, २१; १०३, ९; ९. ९, ९; ४२, ६; ६१, २६; ६३, १८; ६४, १८; १०६, १३; १०. ३६, १०; १३.
वीरऽवतः ७. १५, ५.
वीरऽवती ७. ४१, ७.
वीरऽवती १. १२, ११; ९६, ८; ८. ४३, १५; ९. ६१, ६.
वीरवत्ऽतमं १. १, ३.
वीरऽवतः ४. ५०, ६.
वीरऽवतं १. ६४, १५; २. ११, १३; ३. २४, ५; ५. ४, ११; ९. ३०, ३; ९७, २१; १०. ४७, ५.
वीरऽवाहः ७. ४२, २.
वीरऽवाहं ७. ९०, ५.
वीरऽशुंष्मया १. ५३, ५.
वीरऽसूः १०. ८५, ४४.
वीरस्यं १. ८६, ४; १६६, ७; ३. ५५, १८; ६. ४५, ८; ७. १८, १६; ४२, ४; ८. २, २१; ४०, ९; १०. १५९, ६.
वीरा २. ३९, २.
वीराः १. ७३, ३; ८५, १; १६४, ४३; ३. ५३, ७; ५६, ८; ५. ४१, ९; ८५, ४; ६. २६, ७; ६६, १०; ७. १, १५; १०. १०, २; २७, १७; ७७, ३; १०३, ११.
वीरान् १. ७३, ९; ११४, ८; १४०, १२; २. १४, ७; २४, १५; २५, २; ३०, ४; ३३, ४; ३. ३१, १०; ३६, १०; ५. ४२, १८; ६. ३५, २; ७. ३४, २०; ९९, ५; १०. १८, १; १३२, ५.
वीराय ५. ६१, ५; ६. २३, ३; ३२, १; ४४, १४; ४९, १२; ६५, ४; ८. २, २३; २५; ३२, २४; ४७, १२.
वीरासः ६. ७, ३; ७. १८, १४; १०. २७, १५.
वीरासः ५. ६१, ४.
वीरिणी १०. ८६, ९; १०.
वीरुत्ऽसु १. ६७, ५.
वीरुधः १. १४१, ४; २. ३५, ८; १०. ४०, ९; ४५, ४; ७९, ३; ९१, ६; ९७, ३.
वीरुधः १०. ९७, २१.
वीरुधं १०. १४५, १.
वीरुधां २. १, १४; ९. ११४, २.
वीरेण ९. ३५, ३.
वीरेण्यः १०. १०४, १०.
वीरेभिः २. २५, २; ९. ९६, ११; १०. ६८, १२.
वीरेषु २. २४, १५; १०. ९३, १०.
वीरैः १. ७३, ९; १२२, १; ४. २९, २; ५. २०, ४; ६. ३५, २; ७. ९०, ६; १०४, १५.

वीर्यं १. ५७, ५^2; ८०, ७; ८; ९३, ४; १०३, ७; १६३, ८; २. १३, ११; १७, ३; ३. १२, ९; ३३, ७; ४. ३०, ८; ५. ४२, ६; ५४, ५; ६. १८, ३; ७. २२, ८; ८. ५४, १; ५५, १; ६२, ७; ९. ८, १; ११३, १; १०. ४३, ५; ८७, २५; ९७, १९.
वीर्यस्य १. ९१, २३; १३१, ४; ५.
वीर्या १. ८०, १५; २. १६, २; २१, ३; ३०, १०; ४. ३२, १०; ५. २९, १३; ६. ५९, १; ७. १८, १४; ८. २४, २१; ६३, ६; १०. ३९, ५; ११२, १; ८.
वीर्याणि १. ३२, १; १०८, ५; ११७, २५; १५४, १; १६२, १; ३. २५, २; ३०, ३; ४६, १; ६०, ४; ८. ६२, २; १००, १; १०. ११३, ७; ११७, ९.
वीर्याय १. ६१, १४; १०३, ५; ३. ३२, ५; ३६, ५; ६. १९, १; ३०, १; ३६, २; ७. २०, १; ८. ६१, १८; ९. ११०, ७; १०. ३०, ४.
वीर्ये ६. २८, ८.
वीर्येण १. ५५, ३; १५४, २; २. ११, ५; ४. १८, ५; २७, २; ५०, ७; ५. २९, १४; ६. १८, ७; १०. १०४, ४.
वीर्यैः २. २२, ३; ३. ५४, १५.
वीळयस्व ३. ५३, १९; ६. ४७, २६; ३०.
वीळयस्व २. ३७, ३.
वीळयासि ८. ४५, ६.
वीळवः ८. ८८, ३.
वीळवे ६. २४, ८; ८. ४४, २७.
वीळित ३. ५३, १९.
वीळितः २. २१, ४.
वीळिता २. २४, ३; ६. २२, ६.
वीळु १. ६, ५; ३९, २; ७१, २; १२७, ३; ५; ४. ३, १४; ८. ४०, १; ४५, ६; ७७, ९; १०. ८९, ६.
वीळुऽअंगः ६. ४७, २६.
वीळुऽअंगं १. ११८, ९.
वीळुऽअंगे ८. ८५, ७.
वीळुः ३. ५३, १७.
वीळुऽजंभं ३. २९, १३.
वीळुऽद्वेषाः २. २४, १३.
वीळुपत्मंऽभिः १. ११६, २.
वीळुपविऽभिः ५. ५८, ६; ८. २०, २.
वीळुऽपाणिः ७. १, १४.
वीळुपाणिऽभिः १. ३८, ११.
वीळुपाणी इति वीळुऽपाणी ७. ७३, ४.
वीळुं १०. ४५, ६.
वीळुऽहंराः १०. १०९, १.
वीळुऽहर्षिणः २. २३, ११.
वीळो इति ३. ५३, १९.
वीळोः १. १०१, ४.
वीळौ ३. ३१, ५; ८. ४५, ४१.
वीविजः ८. ७९, ८.
वीहि ३. २८, ३; ४१, ३; ४. १, ५; ६. २, ११; ७. १७, ३.
वीहि २. ३६, ४; ६. ५०, २.
वुरीत ५. ५०, १; ६. १४, १.
वृक ८. ५५, १; ५६, १.
वृकः १. ४२, २; १०५, ७; १८; १८३, ४; २. २३, ७; २८, १०; ६. ५१, १४; ८. ३४, ३; ५१, २; ५६, २; ६६, ८; ९. ७९, ३.
वृकऽताति २. ३४, ९.
वृकतिः ४. ४१, ४.
वृकंऽद्वरसः २. ३०, ४.
वृकं १. १०५, ११; ७. ३८, ७; १०. १२७, ६.
वृकऽयुः १०. १३३, ४.
वृकस्य १. ११६, १४; ११७, १६; २. २९, ६; १०. ३९, १३.
वृकाः १०. ९५, १४.
वृकाणां ८. ६७, १४.
वृकात् १. १२०, ७.
वृकाय ६. १३, ५; ५१, ६; ७. ६८, ८.
वृकासः १०. ९५, १५.
वृकीः १. ११७, १८; १८३, ४.
वृकेण १. ११७, २१; ८. २२, ६.
वृक्णः १. १८७, १०.
वृक्णं १०. ८७, ५.
वृक्णासः ३. ८, ७.
वृक्तऽबर्हिषः १. ३, ३; १४, ५; ३. २, ५; ६; ५. ९, २; २३, ३; ३५, ६; ६. ६८, १; ८. ५, १७; ६, ३७; २७, ७; ३३, १; ३६, १; ६०, १७; ६९, १८; ८७, ३; ९७, १; ९. ११०, ७; १०. ९१, ९.
वृक्तऽबर्हिषः १. ३८, १; ८. ७, २०; २१.
वृक्तऽबर्हिषं १. ४०, ७.
वृक्तऽबर्हिषे १. १२, ३; ३. ५९, ९; १०. ६१, १५.
वृक्त्वी १०. ८७, २.
वृक्ष्यं १०. १२७, ६.
वृक्ष्ये १. ११६, १६; ११७, १७; ६. ५१, ६.
वृक्षः १. १८२, ७; ४. २०, ५; १०. ३१, ७.
वृक्षऽकेशाः ५. ४१, ११.
वृक्षं १. १३०, ४; १६४, २०; २. १४, २; ३९, १; ३. ४५, ४; ५. ५४, ६; ७८, ६; ७. ९५, ५; ८. ७३, १७; ९. ९७, ५३; १०. १०, १३; ४३, ४.
वृक्षस्य ६. २४, ३; ५७, ५; १०. ९४, ३.
वृक्षाः ८. ४, २१; १०. ९७, २३.
वृक्षाःऽइव ८. ४, ५.
वृक्षात् १०. ६८, ८.
वृक्षान् ५. ८३, २.
वृक्षि १. २७, १३.
वृक्षे १. १६४, २२; १०. १२७, ४; १३५, १.
वृक्षेऽवृक्षे १०. २७, २२.
वृंक्त १. १७२, ३.
वृंक्ते १०. ११७, ७.
वृक्ति ६. ७५, १२; १०. ८७, ११.
वृचयां १. ५१, १३.
वृचीवंतः ६. २७, ५; ७.
वृचीवंतः ६. २७, ६.
वृजध्यै ३. ३१, १७.
वृजनं १. ४८, ५.
वृजनं १. १६५, १५; १६६, १५;

१६७, ११; १६८, १०; १६९, ८; १७१, ६; १७३, ६; १३; १७४, १०; १७५, ६; १७६, ६; १७७, ५; १७८, ५; १८०, १०; १८१, ९; १८२, ८; १८३, ६; १८४, ६; १८५, ११; १८६, ११; १८९, ८; १९०, ८; ५. ४४, १; ६. ११, ६; ३५, ५; ७. ६१, ४; ९. ८७, २.
वृजनस्य १. ९१, २१; १०१, ११; ९. ९७, १०.
वृजना ५. ५४, १२; ९. ९६, ७; १०. १७६, १.
वृजनाः ७. ३२, २७.
वृजनानि १. ७३, २.
वृजनीषु १. १६४, ९.
वृजने १. ५१, १५; ६०, ३; ६३, ३; १०१, ८; १०५, १९; १२८, ७; १६६, १४; २. २४, ११; ३. ३६, ४; ५. ५२, ७; ९. ८२, ४; १०. २७, ५; ६३, १५; ६६, २.
वृजनेन ३. ३४, ६; १०. ४२, १०.
वृजनेषु २. २, १; ९; ३४, ७; ६. ६८, ३; ७. ९९, ६; ९. ७७, ५; १०. २७, ४; २८, २.
वृजन्यस्य ९. ९७, २३.
वृजिनं ६. ५१, १३; ७. १०४, १३; ९. ९७, १८; १०. ८७, १५.
वृजिनऽयन्तं १०. २७, १.
वृजिनऽवर्तनिं १. ३१, ६.
वृजिनस्य ९. ९७, ४३.
वृजिना २. २७, ३; ४. १, १७; २, ११; ६. ५१, २; ७. ६०, २; १०. ८९, ८; १०५, ८.
वृजिनाः ५. ३, ११.
वृजिनान् ३. ३४, ६.
वृजिनानां ८. ६७, ९.
वृजिनानि ४. २३, ८; ५. १२, ५; ६. ५२, २.
वृजिने ६. ४६, १३.
वृज्यते १. ८३, ६.
वृज्यते १०. ११०, ४.
वृज्याः २. ३३, १४; ६. २८, ७; ७. ८४, २.
वृज्यां २. २७, ५.
वृज्याम ८. ४५, १०.
वृञ्जते ७. २, ४.
वृञ्जन्ति ६. ३६, २; १०. १२०, ३.
वृञ्जसे ८. ७६, १.
वृञ्जे १. १४२, ५; ६. ११, ५; १०. ६१, १७.
वृञ्जे १. ११६, १.
वृणक् ६. १८, ८.
वृणक् ७. १८, १२; ८. ९७, ७.
वृणक्ति ४. ७, १०; ६. ५१, १६.
वृणक्ति १. १२४, ६; ३. २९, ६; ६. ४७, १७.
वृणक्तु ७. ४६, ३; ६०, ९; ८. ६७, ८; १०. १६५, २.
वृणक्षि १. ५४, ५.
वृणक्षि १०. १४२, ३.
वृणजन् ८. ४७, ५.
वृणते १. ५८, ७; १०. ११, ४.
वृणते १. १४१, ६; ४. १९, १; ५. ११, ४; ६. १७, ८; १०. ९१, ८; ९; १४७, २; १६४, २.
वृणानः १. १०८, ६; ९. ९४, १; १०. १२४, ४.
वृणाना ५. ४८, १.
वृणानाः ३. ४, ५; ५. ११, ४; ७. १८, १२; १०. १८, ६; ८८, ४; १२४, ८.
वृणीत ३. ३९, ७; ५. ५०, १; ८. ६, ४४.
वृणीते १. ६७, १; ४. २५, ३.
वृणीध्वं ५. २८, ६.
वृणीमहे ३. २, ४; ४. ४१, ७; ५३, १; ८. ३१, १०; ९. ६६, १८[२]; १०. १२६, २.
वृणीमहे १. १२, १; ३६, ३; ३९, ७; ४२, ५; ४४, ३; ११४, ४; ९; १३९, १[२]; २. २६, २; ४१, १९; ५. २०, ३; २६, ४; ८२, १; ७; ७. ९७, २; ८. ४, १५; १४, ६; १८, १६; २५, १३; २६, २१; २७, २२; ४४, २०; ६०, १; ८३, १; ९०, २; ९. ६१, ४; ६५, ९; २८; १०. २१, १; ३५, १; २; ३६, २; ११; १००, १.
वृणीष्व १०. १२७, ८.
वृणीष्व ४. ३१, ११; ७. १९, ९.
वृणे १. १७, १; ३. १२, ३; ५; १९, १; ३३, ११; ३७, ९; ७. ५९, ११; ८. ३८, १०; ९४, ८.
वृणोति ७. ८२, ६.
वृण्वते १. ५, ४.
वृण्वते ८. ४५, २१.
वृण्वते ७. ३२, १६.
वृण्वे ४. २१, ८.
वृत ९. १०१, १३.
वृतः १. १७४, ३; ४. १७, ९; ७. ९८, ४.
वृतः ७. ७, ५; १०. ५२, १; ९८, ७.
वृतं १. १०२, ४; ८. ४५, ३.
वृतं ६. १७, १२.
वृतंऽचयः २. २१, ३.
वृतया ५. ४८, २.
वृता ४. ३१, १.
वृताऽइव ६. १, ३.
वृताः ४. ४२, ५.
वृतान् ४. १९, ५; ४२, ७.
वृताभ्यः १०. ३०, ७.
वृतासः ७. ३३, ५.
वृतौ ५. ३७, ५; १०. ६५, ५.
वृत्तं १. १५५, ६; ४. ३१, ४; ५. ३६, ३.
वृत्रः १. ३२, ७; ८; ८०, १२.
वृत्रऽखादः ३. ४५, २; ५१, ९.
वृत्रऽखादं १०. ६५, १०.
वृत्रऽघ्नः ८. ६६, १०; ७८, ७.
वृत्रऽघ्ना १. १७५, ५.
वृत्रऽघ्नी ६. ६१, ७.
वृत्रऽघ्ने ३. ३१, १४; ५. ८६, ३; ९. ९८, १०.
वृत्रऽतरे १. ३२, ५.
वृत्रऽतुरे ४. ४२, ८; ६. २०, १; १०. ४८, ८; ९९, १.
वृत्रऽतुरा ६. ६८, २.
वृत्रऽतूर्ये २. २६, २; ६. १३, १; १८, ६; ३४, ५; ६१, ५; ८. ७,

२४; १९, २०; ७४, ९; १२; १०. ६६, ८; १०४, ९.

वृत्रऽतूर्येषु १. १०६, २; ६. ३८, ५; ८. ३७, १.

वृत्रऽपुत्रा १. ३२, ९.

वृत्रं १. २३, ९; ३२, ५; ११; ३३, १३; ३६, ८; ५१, ४; ५२, २; ८; ५६, ५; ६१, १०; ६३, ४; ८०, २–४; १०; ११; १३; ८५, ९; १०३, ८; १२१, ११; १६५, ८; १७४, २; १८७, १; २. ११, ९; १८; १४, २; १९, ४; ३. ३०, ८; ३२, ६; ३३, ६; ३४, ३; ३६, ८; ४७, ३; ५३, ११; ४. १६, ७; १७, १; ३; ८; १८, ७; ११; १९, ८; २१, १०; ५. ३७, ४; ६. १३, ३; १७, १; २०, २; ३७, ५; ६०, १; ६८, ३; ७२, ३; ७. १९, ५; २०, २; २१, ६; ४८, २; ५८, ४; ८. २, ३२; ३६; ३, १९; ६, १३; ७, २३; ९, ४; १२, २६; २१, १२; ३२, २६; ६२, ८; ७६, ३; ८९, ३; ४; ९९, ६; १००, १२; ९. ६१, २०; १०. २८, ७; ४२, ५; ८९, ७; १०४, १०; १११, ६; ११३, २; ६; ८; १२४, ६; १४७, १; २.

वृत्रस्य १. ३२, १०; ५२, ६; १०; १५; ५४, १०; ५६, ६; ६१, ६; ८०, ५; १०; ३. ३२, ४; ५. ४२, ५; ८. ६, ६; ७६, २; ९६, ७; १००, ७; १०. १५२, ३.

वृत्रऽहत्याय ५. २९, ७; ६. १८, ९; ८. ८९, ५; १०. ५५, ७.

वृत्रऽहत्ये १. ५२, ४; १०९, ५; ४. १९, १; २४, २; ६. २३, २; २५, १; ८; ३६, २; ४७, २; ७. १९, १०; ८. ६३, १२; १०. २२, १०; ४८, ८.

वृत्रऽहत्येन ८. २४, २.

वृत्रऽहत्येषु १. ५३, ६; ७. १, १०; १९, ३; ३२, १५; १०. ६५, २.

वृत्रऽहथानां ३. १६, १.

वृत्रऽहन् ८. ६४, ९.

वृत्रऽहन् १. ८४, ३; ३. ३१, १८; ४०, ८; ४१, ४; ४. ३०, १; ७; १९; २२; ३२, १; १९; २१; ५. ३८, ४; ६. ४५, ५; ७. ३१, ६; ३२, ६; ८. १, १४; १३, १५; १७, ९; २४, ८; ३३, १; १४; ३७, १; ५४, ५; ६२, ११; ६६, ११; ८२, १; ९२, २४; ९३, ४; ३३; १०. १०३, १०; १५२, ३.

वृत्रऽहनं १. ५९, ६; १०६, ६; १२१, १२; ४. ४२, ९; ६. १६, १४; १७, ११; २०, ९.

वृत्रऽहना ३. १२, ४; ८. ३८, २.

वृत्रऽहना ६. ६०, ३; ७. ९३, १; ४.

वृत्रऽहनौ १. १०८, ३.

वृत्रहन्ऽतम ५. ३५, ६; ४०, १; ८. ३, १७; ६, ३७; २४, ७; ९७, ५; ९. २४, ६; १०. २५, ९.

वृत्रहन्ऽतमः ८. ४६, ८; ९२, १७; ९३, ३२; ९. १, ३.

वृत्रहन्ऽतमं १. ७८, ४; ६. १६, ४८; ८. ७४, ४; ८९, १; ९३, १६.

वृत्रहन्ऽतमा ८. ८, ९.

वृत्रहन्ऽतमा ७. ९४, ११.

वृत्रहऽभिः ६. ६०, ३.

वृत्रऽहा १. १६, ८; ७४, ३; ८१, १; ९१, ५; १००, २; १८६, ६; २. १, ११; २०, ७; ३. २०, ४; ३०, ५; ३१, ११; २१; ४७, २; ५२, ७; ५४, १५; ५. ४०, ४; ६. १६, १९; ४७, ६; ८. २, २६; ४, ११; ६, ४०; २४, २; २७, ८; ३२, ११; ४५, ४; २५; ४६, १३; ६१, १५; ६६, ३; ९; ७०, १; ७७, ३; ८९, ३; ९०, १; ९३, २; १५; १८; २०; ९६, १९; ९. २५, ३; २८, ३; ३७, ५; ८९, ७; ११३, १; १०. २३, २; ४९, ६; ६९, १२; ७४, ६; ८३, ३; १११, ६; १३३, १; १३८, ५; १५२, २; १५३, ३; १७०, २.

वृत्रा १. ८, २; ३. ३०, ४; ४. १७, १९; २२, ९; ४१, २; ६. २२, १०; २९, ६; ३३, १; ७. १९, ४; २५, ५; ८३, १; ८. ९०, ४; ९. १०९, १४.

वृत्राऽइव १०. ४९, ६.

वृत्राणां १. ४, ८; ३. ४९, १; ६. २६, ८; ८. ९६, १८; ९. ८८, ४.

वृत्राणि १. ५३, ६; ८४, १३; १०२, ७; ३. ३०, २२; ४. २४, १०; ४२, ७; ६. १६, ३४; १९, १३; ३३, ३; ४४, १४; ५६, २; ५७, ३; ६०, ६; ७३, २; ७. २२, २; २३, ३; ३०, २; ८३, ९; ८५, ३; ९२, ४; ८. १५, ३; ११; १७, ८; ९; २९, ४; ४९, २; ९०, ५; ९५, ९; १००, २; ९. १, १०; १७, १; २३, ७; ११०, १; १०. ६९, ६; ८०, २; ८३, ७.

वृत्रात् १०. १२४, ८.

वृत्राय १. ६१, १२; २. ३०, २; ३; ३. ३७, ५; ६; ८. १२, २२; ९३, ७; ९. ६१, २२; १०. ११६, १.

वृत्रे ६. २५, ६; १०. ५०, २.

वृत्रेण १०. ११३, ३.

वृत्रेषु १. ७, ५; ६. २६, २; ४६, १; ७. ३४, २.

वृत्वा १०. ९०, १.

वृत्वी १. ५२, ६.

वृथक् ८. ४३, ४; ५.

वृथा १. ५८, ४; ६३, ७; ८८, ६; ९२, २; १३०, ५; १४०, ५; १६८, ४; २. १५, ३; २४, ९; ५. ५६, ४; ६. १२, ५; ८. २०, १०; ९. १६, ७; २१, ३; २२, २; ३०, १; ६४, १७; ७६, १; ८८, ५; ९; ९७, ९; १०९, २१; १०. २६, ७; ६१, २४.

वृथाऽइव १०. ९३, १३.

वृथाषाट् १. ६३, ४.

वृद्धऽआयु १. १०, १२.

वृद्धः १. ५, ६; २. २२, ३; ५. ६०, ३; ६. ४४, ३.

वृद्धं ३. १, १४; ३२, ७; ४. १९, १; ७. १८, १२; ८. ६०, ७.

वृद्धऽसंहाः ६. २०, ३; ३७, ५.
वृद्धंयः १. १०, १२.
वृद्धऽवंयाः २. २७, १३.
वृद्धऽशंवसः ८. २५, १०.
वृद्धऽश॒व॒सः ५. ८७, ६.
वृद्धऽशोंचिषः ५. १६, ३.
वृद्धऽश्रंवाः १. ८९, ६.
वृद्धऽसेंनाः १. १८६, ८.
वृद्धस्यं १. ५१, ९; ६. २४, ७.
वृद्धाः १. ३८, १५; ५. २०, २.
वृद्धासुं १०. ९१, १२.
वृधः १. ८१, २; ५. ३४, ६; ६. १५, ३; २०, ११; ३४, ५; ४८, २; ७. ३०, १; ३२, २५; ८. १२, १८; १३, २; ३२, १८; ९८, ५; ६; १०. ६, ४; २६, ९; ६९, ११; ८९, ११.
वृधंतः ६. ४९, ११; ८. २, २९.
वृधंते ६. ६६, ११; ८. १०२, ७.
वृधंता १. १५८, १.
वृधंतौ ५. ८६, ५.
वृधे १. १६७, ४; ३. १६, २.
वृ॒ध॒सा॒नः ४. ३, ६; ६. १२, ३.
वृ॒ध॒सा॒नासुं २. २, ५.
वृधसें ५. ६४, ५.
वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू ४. २, ३.
वृधस्यं ८. १३, १.
वृधा ८. ७५, १४.
वृ॒धा॒न् ७. ९९, १.
वृ॒धा॒नः १. ५५, ६; ९५, ११; ९६, ९; ३. २८, ६; १०. ५५, ८; ८१, ५; ९९, ६.
वृधां १०. ८९, १०.
वृधायं ८. ८३, ६.
वृधासंः १. १७१, २; १८६, २; ४. २, १०; ७. ९१, १; ८. ८३, २; ९३, २३; १०. १४७, ३.
वृ॒धि॒ १. ७, ६; १०, ७; २. २, ७; ४. ३१, १३; ७. २७, २; ८. २३, २९; ९. ४५, ३; ६४, ३.
वृ॒धी॒कः ८. ७८, ४.
वृधे १. ३४, १२; ७९, ११; ८५, १; ८९, १; ५; ९१, १०; १७; ११२, २४; १२१, ८; १७८, ५; ३. ३, ८; ६, १०; ४. २, १८; २३, २; ५. ९, ७; ६. ३३, ४; ४६, ३; ११; ७. २४, १; ८. ३, १; १३, ३; २७, ४; ५४, ५; ६०, १०; ६३, १०; ७७, ५; ९७, ११; ९. ४३, ६; १०. ३५, ११; ४४, ४; १००, १.
वृ॒श्च॒ १. ५१, ७; ३. ३०, १६; १७; ९. ९१, ४.
वृ॒श्च॒ ६. ८, ५; ८. ४०, ६; १०. ८७, १०; ११६, ५.
वृ॒श्चः॒ ४. १७, ७.
वृ॒श्च॒त् १. ६१, १०; २. १९, २.
वृ॒श्च॒ति॒ ३. ५३, २२.
वृ॒श्चत्ऽवंनं ६. ६, १.
वृ॒श्चंतः १०. २८, ८.
वृ॒श्चंतिं ६. २, ९.
वृ॒श्च॒सि॒ १. १३०, ४[२].
वृ॒श्चात् १०. ५३, ९.
वृ॒श्चि॒कः॒ १. १९१, १६.
वृश्चिंकस्य १. १९१, १६.
वृ॒श्च॒यं॒तां १०. ८७, १८.
वृ॒ष॒ऽक॒र्म॒न् १. ६३, ४; १३०, १०.
वृषंऽक्रतुः ६. ४५, १६.
वृषंऽक्र॒तो॒ इ॒ति॒ वृषंऽक्रतो ५. ३६, ५.
वृषंऽखादयः १. ६४, १०.
वृषंऽगणाः ९. ९७, ८.
वृषंऽच्युताः ९. ६९, ७.
वृषंऽजूतिः ५.३५, ३; ८. ३३, १०.
वृषंणः १. १०९, ३; १६५, १; १७७, २; १७९, १; १८१, २; १८६, ५; २. १६, ८; ३. २७, १५; ५४, २०; ४. २, २; ६, ९; ४१, ६; ५. ३१, ५; ४७, ६; ६. २९, २; ४४, १९[२]; २०; ७. २१, २; ७१, ३; ८. १, ९; २०, १२; २३, ११; ३३, ११; १०. ५, २; ६६, ६[४]; ७; ९२, ७; ९४, ६.
वृ॒ष॒णः॒ १. ८५, १२; २. ३३, १३; ४. ३५, ६; ७. ५६, १८; २०; २१; ५८, ६; ६०, १०; ८. ९६, १४.
वृषंणं १. १६, १; ६४, १२; ८२, ४; ८५, ७; १०१, १; ११८, ९; १२७, २; १२९, ३; १३१, ३; १५७, २; १७७, ३; १७९, ४; २. १६, ५; ३. २७, १५; २९, ३; ९; ४. १७, १६; २४, ७; ८; ५. ३६, ५; ४०, ३; ७५, १; ६. १९, ८; ६७, ११; ७. २०, ५; २३, ६; २४, ४; ८८, १; ८. १, १; १५, ४; ३३, १२; ६१, ११; ९४, १२; ९. ६, ६; ६३, २१; ९०, २; ९७, ४९; १०६, १; ३; ५; १०. २७, १०; २८, ७; ४७, १; ६७, ९; १०.
वृ॒ष॒ण॒श्वस्यं १. ५१, १३.
वृ॒ष॒ण॒श्वेनं ८. २०, १०.
वृषंणा १. १०, ३; १७७, १; २. १६, ५; ६; ३. ३५, ३; ५; ४३, ४; ५७, २; ७. १९, ६; ८. ४, ११; १४; १३, २३; ३१; ३३, ११; ६१, १८; १०. ४९, २; ६६, ६; ७; १०२, १२; ११४, ३.
वृ॒ष॒णा॒ १. ९३, १; ७; १०८, ३; ११२, ८; २४; ११७, ३; ४; ८; १२; १५; १८; २५; ११८, १; ६; ११९, ४; १५१, २; ३; १८१, ८; १८३, १; १८४, २; २. ४०, ३; ४. १४, ४; ६. ६२, ७; ६८, ११; ७. ७०, ७; ७३, ३; ७४, ३; ८२, २; ८३, ९; १०४, १; ८. २२, ७; १२; १६; २६, १; २; १२; ३५, १५; १०. ३९, ९.
वृषंणो १०. ६६, ७.
वृ॒ष॒णौ॒ १. १०८, ७–१२; ११६, २१; ११७, १९; १५३, २; १५७, ५; १५८, १; १८०, ७; ७. ६०, ९; ६१, ५.
वृ॒ष॒ण्य॒ति॒ ९. ५, ६.
वृ॒ष॒ण्यंतीभ्यः ९. १९, ५.
वृषंण्ऽवती ८. ६८, १८.
वृषंण्ऽवंतं १. १००, १६.
वृषंण्वसू इ॒ति॒ वृषंण्ऽवसू १. १११, १.
वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू २. ४१, ८;

४. ५०, १०; ५. ७४, १; ७५, ४; ९; ८. ५, २४; २७; ३६; २२, ८; ९; २६, १; २; ५; १५; ७२, १०; ८५, ७; १०. ९३, ५.
वृषण्ऽवान् १. १२२, ३; १७३, ५; १८२, १.
वृषत्ऽअंजयः ८. २०, ९.
वृषऽत्वना ८. १५, २.
वृषऽत्वा १. ५४, २.
वृषऽत्वेभिः १. ९१, २.
वृषऽधूतस्य ३. ३६, २; ४३, ७.
वृषन् १. १३९, ६; ५. ४०, १; ८. ३३, १२; ९. ४०, ६; ५१, ४; १०. ८९, ९.
वृषन् १. ७, ६; १३१, ५; २. १७, ८; ३. २७, १५; ५. ३३, २; ६. १, १; २२, ८; ३३, १; ४४, २०; ७. ३१, ४; ८. ७०, ६; ९२, १५; २३; ९३, १९; ९. ६४, २; १०. ९६, १३; १५३, २; १९१, १.
वृषऽनाभिना ८. २०, १०.
वृषनाम ९. ९७, ५४.
वृषन्ऽतमः १. १००, २; ६. ५७, ४.
वृषन्ऽतमं १. १०, १०.
वृषन्ऽतमस्य १. १०, १०; ५. ३५, ३.
वृषधिं ४. २२, २.
वृषऽपत्नीः ८. १५, ६.
वृषऽपर्वा ३. ३६, २.
वृषऽपाणयः ६. ७५, ७.
वृषऽपानासः १. १३९, ६.
वृषऽपानेषु १. ५१, १२.
वृषऽप्रभर्मा ५. ३२, ४.
वृषऽप्रयाव्ने ८. २०, ९.
वृषऽप्सवः ८. २०, ७.
वृषऽप्सुना ८. २०, १०.
वृषभ १. १६५, ७; १७१, ५; १७७, ३; २. ३, ११; ९, २; १६, ६; ३३, ४; ७; १५; ३. ६, ५; १५, ३; ६; ३०, ३; २१; ३५, ३; ४६, ५; ६. २२, ४; ४४, ११; २१; ८. २१, ४; ११; ४५, २२; ३८; ६०, १४; ९६, १८; ९. ८६, ३८; १०. ३८, ५; ११२, ७; १८०, ३.
वृषभऽअन्नाय २. १६, ५.
वृषभः १. ३१, ५; ३३, १०; ५४, २; ३; ७९, २; ११६, १८; १२८, ३; १४०, १०; १७७, १; १८१, ६; १९०, ८; २. १, ३; १२, १२; २१, ४; २३, ११; ३३, ६; ३. १५, ४; ३०, ९; ३१, १८; ३६, ५; ३८, ५; ४७, १; ४८, १; ५०, १; ५५, १७; ५६, ३[२]; ४. ३, १०; ५, ३; ५८, ३; ५. १, ८; २, १२; २८, ४; ३०, ११; ३२, ६; ४०, ४; ४३, १३; ५८, ६; ८३, १; ६. १७, २; १९, ९; २२, १; ४१, ३; ४४, २१; ४७, ५; २१[२]; ७३, १; ७. ५, २; १९, १; ३६, ३; ४९, १; ५५, ७; ९५, ३; १०१, १; ६; ८. ५७, ३; ६०, १३; ६४, ७; ९३, ७; २०; ९६, २; ९. ७०, ७; ७२, ७; ७६, ५; ८५, ९; ९६, ७; १०८, २; ११०, ९; १०. ४, ५; ५, ७; ८, २; २८, २; ७५, ३; ८६, १५; ९२, १०; १०२, ६; १०३, १; १११, २.
वृषभं १. ९, ४; ३३, १४; १५; १६०, ३; १९०, १; २. ३०, ८; ३. ४, ३; ४०, १; ४७, ५; ६२, ६; ४. १७, ८; १८, १०; २४, ५; ६. १, ८; १८, १; २६, ४; ७. २६, ५; ८. १, २; ६१, २; ७२, १३; ९३, १; ९६, ४; ६; ९. ८०, ५; १०८, ८; ११; १०. २७, २; २८, ९; ४४, ३; ४८, १०; १०२, ५.
वृषऽभरान् १०. ६३, ३.
वृषभस्य १. ५९, ६; १४१, २; १६६, १; २. १६, ६; ३. ३८, ७; ४३, ६; ४६, १; ४. १, ११; १२; ७. ७९, ४; ९. १९, ४; १०. ४०, ११; ४३, ३; १०२, ९.
वृषभस्यऽइव १. ९४, १०.
वृषभा ५. ६३, ३; १०. २७, ३; ६५, ९.
वृषभा ६. ४९, ६.
वृषभाऽइव ४. ४१, ५; ६. ४६, ४.
वृषभाः १०. ९४, ३.
वृषभाणां ८. ५३, १.
वृषभाणि २. १६, ६.
वृषभान् १०. २८, ३.
वृषभाय १. ५१, १५; १०३, ६; २. १६, ४; ५[२]; ३३, ८; ४. १६, २०; ५. १, १२; १२, १; ६. ४४, २०; ७. ९८, १; १०. १०, १०; १८७, १.
वृषभासः १. १७७, २; २. १६, ५; ५. ६९, २.
वृषऽभिः १. १००, ४; १७३, २; १७९, २; ३. ४२, ७; ५. ४०, १; ६. ५, ४; ४४, २०; ७. ६९, १; ९. ३४, ३; ९७, २८; १०. ६७, ७; ११२, २.
वृषभेण १. ३३, १३; २. १६, ४; १०. ९९, ११.
वृषऽभ्यां १. १७७, ३; ५. ३६, ५.
वृषऽमनः १. ६३, ४; ४. २२, ६.
वृषऽमनाः १. १६७, ७.
वृषऽमन्यवः १. १३१, २.
वृषय १०. ९८, १.
वृषऽयते ९. ७१, ३; १०८, २; १०. ९४, ९.
वृषऽयते १. ५५, २; ९. ४७, १.
वृषऽयंते ३. ७, ९.
वृषऽयमाणः १. ३२, ३; ३. ५२, ५.
वृषऽयसे १. ५८, ४.
वृषऽयसे १०. २१, ८; ४४, ४.
वृषऽयुः ९. ७७, ५.
वृषऽयुधः १. ३३, ६.
वृषऽरथः ५. ३६, ५.
वृषऽरथासः १. १७७, २; ६. ४४, १९.
वृषऽरवाय १०. १४६, २.
वृषऽरश्मयः ६. ४४, १९.
वृषलः १०. ३४, ११.
वृषऽव्रतः ९. ६२, ११; ६४, १.
वृषऽव्रातासः १. ८५, ४.
वृषऽशिप्रस्य ७. ९९, ४.
वृषऽशुष्मं ४. ३६, ८.
वृषऽसवासः १०. ४२, ८.

वृषऽस्तुभः १०. ६६, ६.

वृषस्व १. १०४, ९; ३. ३२, २; ४०: २; ६०, ५; ६. ४७, ६; ८. २४, १०; ६१, ३; १०. ९६, १३; ११६, १; ४.

वृषा १. ७, ८; ३६, ८; १०; ५४, २; ५५, ४^{२}; ८०, २; ८७, ४; ९१, २; १००, १; ४; १०४, ७; १३१, ६; १४०, २; १४९, २; १७३, २; १७५, १; २; १७६, १; २; १७७, ३; १८१, ८; २. १६, ४; ६^{२}; १८, २; ३४, २; ३५, १३; ३. १, ८; २, ११; २७, १३; ४४, ४; ६१, ७; ४. ३, १०; १६, ३; २२, २; ३०, १०; ५. ३३, ४; ३५, ४; ३६, ५^{४}; ४०, २^{३}; ३; ४४, ३; ८७, ५; ६. ३, ७; १६, १५; २४, १; ४४, २१^{२}; ४८, ३; ६^{२}; ७. १०, १; २०, ५; ९; ९५, ३; ८. ४, ८; ६, १४; ४०; १३, ३१^{३}; ३२^{२}; ३३; १५, १०; २७, ८; ३३, १०^{२}; ११^{२}; १२^{२}; ६४, ८; ९३, ७; २०; ९. २, १; २; ६; ५, १; ७; ९; ६, १; ७, ३; १५, ४; १९, ३; २५, ३; २७, ३; ६; २८, ४; ३७, १; ५; ३८, १; ४०, २; ६१, २८; ६२, ११; ६३, २०; ६४, १^{३}; २^{३}; ३; ६५, ४; १०; ७०, ५; ९; ७१, ७; ७४, ३; ८०, २; ३; ८१, २; ८२, १; ८६, ३; ७; ११; १२; १९; ३१; ४४; ८७, ४; ९१, ३; ९३, २; ९७, १३; ४०; १०१, १६; १०७, २२; १०८, १२; १०. ११, १; २६, ३; ४३, ६; ८; ४९, ९; ६१, ८; ६६, ६^{२}; ९२, १; ९४, १०; १०२, १२; ११५, २; ८; ११६, ४; १५२, २; १५३, २; १८७, ३.

वृषाऽइव १. १४०, ६; २. २५, ३; ४३, २; ९. ७६, ५; ९६, २०.

वृषाकपायि १०. ८६, १३.

वृषाकपिः १०. ८६, १; ३; १८.

वृषाकपिं १०. ८६, ४; ८.

वृषाकपे १०. ८६, २०–२२.

वृषाकपेः १०. ८६, २; १२.

वृषाणं ९. ३४, ३; १०. ८९, ९.

वृषेथां १. १०८, ३; ६. ६८, ११.

वृषो इति ३. २७, १४; ८. ३३, १०.

वृष्ट्यः २. ३४, २; ५. ५३, २; ६; १०; ८४, ३; ७. १०१, ५; ८. २५, ६; ९. १७, २; २२, २; ५७, १; ६२, २८; १०. ७५, ३.

वृष्टिः १. ३८, ८; १५२, ७; ५. ६३, १; ८५, ३; ६. १३, १; ९. ८९, १; १०. २३, ४; ४३, ७.

वृष्टिःऽइव ७. ९४, १.

वृष्टिऽद्यावः ९. १०६, ९.

वृष्टिऽद्यावा ५. ६८, ५.

वृष्टिऽभिः १. १६४, ५२; ५. ५९, ५; ७. ५६, १३; ८. ७, १६.

वृष्टिं १. ३९, ९; ११६, १२; २. ६, ५; २७, १५; ४. २६, २; ५. ५५, ५; ५८, ३; ६२, ३; ६३, २; ८३, ६; ७. ४०, ६; ६४, २; ८. १२, ६; ९. ८, ८; ३९, २; ४९, १; ३; ६५, ३; २४; ६९, ९; ९६, १४; ९७, १७; १००, ३; १०८, १०; १०. ९८, ३; १०.

वृष्टिऽमंतं १०. ९८, ८.

वृष्टिमान्ऽइव ८. ६, १; ९. २, ९.

वृष्टिऽवनिं १०. ९८, ७.

वृष्टिऽहव्यस्य १०. ११५, ९.

वृष्टी ५. ५३, ५.

वृष्टीऽइव २. ५, ६.

वृष्टेः ९. ७४, ३.

वृष्टेःऽइव ९. ४१, ३.

वृष्ट्या ५. ६३, ४; ८. २१, १८.

वृष्ट्वी ५. ५३, १४.

वृष्णः १. ३२, ७; १०८, ३; ११६, ७; १५४, ६; १६४, ३४; ३५; १८१, ३; २. ११, ९; १०; १६, ५; ६; ३. ७, २; ५; ३६, २; ३८, ४; ४३, ७; ४. ५, १०; १५; २१, ७; २२, ६; ३९, २; ५. १२, २; ६; ४१, १०; ४२, १२; ८३, ६; ६. ६, ५; ८, १; ६८, ११; ७. ३, ३; ५; ८. ४, ७; ७, ३३; २०, १९; २०; ३३, १८; ६३, ९; ९. १०, ६; २९, १; ६४, २; १०. ३, ४; ४४, ८; ९२, ८; १०३, ९.

वृष्णा १. ८४, १०; १०. १०३, २.

वृष्णां ८. ४६, २९; ८३, १.

वृष्णिं ५. ३५, ४; ८. ३, १०; ७, २३.

वृष्णिः १. १०, २.

वृष्णिनां ८. ६, ६.

वृष्णे १. ६४, १; १००, १७; १०३, ६; १५४, ३; १६५, ११; १७५, १; २. १४, १; ३. १, १०; २०; ७, ९; ३०, २; ३५, ७; ५७, ३; ४. १, १२; १६, २०; ५०, ६; ५. १, १२; १२, १; ३१, ५; ६. ४१, ३; ४४, १९–२१; ७. १९, ६; ८. २०, ९; ३४, ५; ७५, ६; ९. ८७, ४; ९१, ३; १०९, २०; १०. ११, १; ९८, ११; १०४, ३; १७५, ३.

वृष्ण्यं १. ५४, ८; ९१, १६; १०५, २; ६. ८, ३; ४६, ८; ८. ३, ८; ६, ३१; ५१, १०; ९. १९, ७; ६४, २; १०. १७५, ३.

वृष्ण्यऽवतः ५. ८३, २.

वृष्ण्यऽवान् ६. २२, १.

वृष्ण्या १. ५१, ७; ५३, ६; १०२, ४; ६. १९, ६; ८. ७०, ६; १०. ५५, ७.

वृष्ण्यानि १. ९१, १८; १०८, ५; ४. १९, १०; २१, २; ६. २५, ३; ३६, ३; १०. ४४, २; ११३, ८.

वृष्ण्येन १०. ४४, १.

वृष्ण्येभिः १. १००, १; ३. ४६, २.

वृह ६. ४५, ९.

वृह ३. ३०, १७; ६. ४४, ११; ८. ४५, ८; १०. १०, ८.

वृहः ६. ४८, १७.

वृहत् १. १३०, ९.

वृहत ८. ६७, २१.

वृहतं ६. ७४, २.

वृहतात् १. १७४, ५; ४. १६, १२.

वृहति १०. ६१, ५.

वृहर्थः २. ३०, ६.
वृहामि १०. १६३, १.
वृहेव १०. १०, ७.
वेः १. ६३, २; ७७, २; १३०, ३; १७३, १; २. ५, ३; ३. ५, ५; ६; ५४, ६; ४. ७, ७; ८; ४०, ३; ६. ३, ५; १५, १४; ९. ७२, ५; १०. ३३, २; १०५, २.
वेः ४. ३, १३.
वेःऽइव १. ११६, १५.
वेणून् ८. ५५, ३.
वेत् १०. ५३, ९.
वेतसः ४. ५८, ५.
वेतसवे ६. २६, ४.
वेतसुं ६. २०, ८.
वेतसून् १०. ४९, ४.
वेति १. ३५, ९; १४१, ६; ५. ३४, ४; ४४, ७; ६. १५, १; ८. ७२, ५; १०१, १०; ९. ७१, १; १०. २१, २; ९९, २.
वेति १. ४८, ६; १८६, ५; ५. ६१, १८; १०. ४, ५; ८, ७; २३, ४; ४३, २.
वेतु ५. १४, ५.
वेतु १. ७७, ४; ५. ११, ४; ७. १५, ६; ४२, १; १०. १६, ५; ३१, १.
वेत्थ ५. ५, १०; ६. १६, ३; ८. २४, २४.
वेत्थ १०. १५, १३.
वेद १. २५, ७^{2}; ८^{2}; ९^{2}; ३१, ५; १६४, ७; २२; ३९; २. १४, १०; ३. ४, १०; ४. ८, २; ५. १२, ३; ६. ४२, ३; ५१, २; ७. ५६, २; ८. ४१, ५; ६१, १२; १०. १०, ५; ३५, १४; ८२, ३; १२९, ७; १६९, २; ३.
वेद १. १०५, ९; १३९, ७; १४५, १; १६४, ३२; १७०, १; १८५, १; ३. ११, १; ३१, ८; ५४, ५; ५५, १०; ४. ८, ३; २३, ३; ५. ५३, १; ६१, १४; ६. १५, १३; २९, ६; ३३, ७; ३९, ६; ४६, १२; ९. ५८, २; ७४, ७; १०. १०, ६; ११, १; १२, ५; १७, ५; २६, ३; २७, ३; ७३, १०; ८८, ८; ९७; १०७, ६; १०८, १०; १११, ३; ५; ७; ११४, ९; १२९, ६; ७; १४९, २.
वेदः १. ७०, ५; ८१, ९^{2}; ९९, १; १०३, ६; ३. ५३, १४; ४. २५, ७; ५. २, १२; ७. १५, ३; १९, १; ८. ४५, १५; ८१, ७; १०. २७, १०; ८४, २; ९९, ३.
वेदः १. ४३, ९.
वेदत् २. ३५, २; ५. ३०, ३; ८. ९६, १०.
वेदत्ता १०. ९३, ११.
वेदति ८. ४५, ४२.
वेदथः ८. २६, ११.
वेदनं १. १७६, ४; ४. ३०, १३; ७. ३२, ७.
वेदना १. ३३, १५.
वेदने १०. ३४, ४.
वेदयामसि ४. ३६, २; ७; १०. १५१, १.
वेदसः २. १७, ६.
वेदसा ३. ६०, १; ८. ८७, २.
वेदसां १. ८९, ५.
वेदिं ४. १६, ४.
वेदिः १. १६४, ३५; ७. ३५, ७.
वेदिता ८. १०३, ११.
वेदिं १. १७०, ४; ५. ३१, १२; ७. ६०, ९; ८. १९, १८; १०. ६१, २.
वेदिष्ठः ८. २, २४.
वेदिऽसत् ४. ४०, ५.
वेदिऽसदे १. १४०, १.
वेदी ६. १, १०.
वेदी इति २. ३, ४.
वेदीयान् ७. ९८, १.
वेदेन ८. १९, ५.
वेद्यः ६. ४, २; ८. १९, ८.
वेद्य २. २, ३; ८. ८४, १.
वेद्या ६. १३, ४.
वेद्यानां १०. २२, १४.
वेद्याभिः १. १७१, १; ३. ५६, १; ६. ९, १; ७. २१, ५; १०. ७१, ८.
वेद्याय ५. १५, १.
वेधः १. ७३, १०; १६९, १; ४. ३, ३; १६; ४२, ७; ६. १६, ३; २२, ११.
वेधःऽतम १. ७५, २.
वेधःऽतमः ६. १४, २.
वेधसः १. ७२, १; १३१, ६; १५६, ४; ४. २, १५; ६, १; ३२, ११; ५. ५२, १३; ६. १५, १७; २५, ६; ७. २६, ३; ३७, ६; ८. २०, १७; ४३, १; ६०, ५; ९९, २; ९. २, ३; ७, ५; १६, ७; २६, ६; २९, २; ६४, २३; ८६, ४; १०. ९१, ९; १२२, ८; १७७, १.
वेधसः ५. ५४, ६.
वेधसे ५. ४३, १२.
वेधसा १. १८१, ७.
वेधसां १. १२९, १^{2}.
वेधसे १. ६४, १; १५६, २; २. २१, २; ३. १०, ५; ५. १५, १; ६. १६, २२; ७. ४६, १; ८. ४३, ११; ९. १०३, १; १०. ९१, १४; १४४, १.
वेधस्या ९. ८२, २.
वेधाः १. ६०, २; ६५, ५; ६९, २; १२८, ४^{2}; १५६, ५; ३. १४, १; ५९, ४; ४. १६, २; ६. ४४, ८; ८. ६०, ३; ९. १०१, १५; १०. १०, १; ६१, १६; ८६, १०.
वेधां ९. १०२, ४.
वेनः १. ८३, ५; १३९, १०; ८. ३, १८; ६३, १; १०. १२३, १; २; ५.
वेनः १. ४३, ९; ५. ३१, २; ३६, ४; ६. ४४, १०.
वेनतः १. ८६, ८; ९. ९७, २२.
वेनतं ५. ७५, ७.
वेनति ८. ६०, ७.
वेनति १०. १३५, १.
वेनन् १०. ६१, १८.
वेनंतः १०. १२३, ६.
वेनंता १. २५, ६.
वेनंति १०. ६४, २.
वेनं ९. २१, ५.

वेनस्यं १. ६१, १४.
वेनाः १. ५६, २; ८. १००, ५; ९. ६४, २१; ७३, २; ८५, १०; १०. ६४, २.
वेनात् ४. ५८, ४.
वेनानां ९. ८५, ११.
वेनां १. ३४, २.
वेनीः ८. ४१, ३.
वेने १०. ९३, १४.
वेन्यः ६. ४४, ८.
वेन्यं १०. १७१, ३.
वेन्यस्यं २. २४, १०; १०. १४८, ५.
वेपः १०. ४६, ८.
वेपंते ९. ७१, ३; १०. ११, ६.
वेपते ५. ३६, ३.
वेपयंतं ८. १२, २.
वेपयंति १. ३९, ५; ३. २६, ४; ८. ७, ४.
वेपसा १. ८०, १२; ४. ११, २.
वेपिष्ठः ६. ११, ३.
वेपीं ६. २२, ५.
वेपेते इति १. ८०, ११.
वेमिं ८. ४, १७[२].
वेमि ८. ४, १७.
वेरिति वेः १. ७२, ९; ९६, ६; १६४, ७; ३. ७, ७; ४. ५, ८; २७, ४; ६. ४८, १७; १०. ५, १.
वेविजानः ४. २६, ५; ९. ७७, २.
वेविजे इति १. १४०, ३.
वेविज्यते १. ८०, १४.
वेविदानः ५. १९, ५.
वेविदानाः १. ७२, ४; ३. ५४, ४.
वेविदाम ७. २४, ६.
वेविपत् ३. २, १०; ८. १९, ११; १०. ९१, ७; १०९, ५.
वेविपतः ६. २१, ५.
वेविषाणाः ७. १८, १५.
वेवीयते १०. ३३, २.
वेवेति ३. ५५, ९; ४. ३८, ६.
वेशं ५. ८५, ७; १०. ४९, ५.
वेशाय १. १७६, २.
वेशस्यं ४. ३, १३.
वेशीत् ८. ६०, २०.
वेश्मं १०. १०७, १०.
वेश्मंऽइव १०. १४६, ३.
वेश्यं ४. २६, ३.
वेश्या ६. ६१, १४; ७. १८, १७.
वेषणा ४. ३३, २.
वेषंणे ५. ७, ५.
वेषंत् १. १८०, ६.
वेषंतीः १. १८१, ६.
वेषिं १. ७४, ४; ७६, ४; १७३, ८; १८९, ७; २. २४, १५; ४. ९, ५; ६; ५. ३०, ४; ६. ४, ८; १२, ६; ७. १६, ५; १०. ८, ५.
वेषि ८. ११, ४.
वै १. १०५, २; १६२, २१; २. ३३, ९; १०; ५. १७, ३; ४०, ९; ४४, ७; ७३, ९; ७. २०, २; ४; ८५, २; १०४, १३; ८. २३, १३; ५८, २; ६२, १२; ७६, ४; ९. ११२, १; १०. १०, १२; २७, ५; ३२, ७; ९५, १५; १०९, ६; ११७, १; ११९, १; १३७, ६; १४२, ३; १४६, ५; १६४, २.
वैकर्णयोः ७. १८, ११.
वैतरणः १०. ६१, १७.
वैतसेनं १०. ९५, ४; ५.
वैदत्ऽअश्विः ५. ६१, १०.
वैदथिनायं ४. १६, १३; ५. २९, ११.
वैन्यः ८. ९, १०.
वैभुऽवसः १०. ४६, ३.
वैयंश्व ८. २४, २३.
वैयश्व ८. २३, २४.
वैयश्वस्यं ८. २६, ११.
वैरंऽदेये ५. ६१, ८.
वैरिणाः १. १९१, ३.
वैरूपैः १०. १४, ५.
वैलऽस्थानके १. १३३, ३.
वैलऽस्थानं १. १३३, १.
वैवस्वतः ९. ११३, ८.
वैवस्वतं १०. १४, १; ५८, १.
वैवस्वतात् १०. ६०, १०.
वैवस्वते १०. १६४, २.
वैशंतं ७. ३३, २.
वैश्यः १०. ९०, १२.
वैश्वांनर १. ५९, १; २; ५; ९८, ३; ३. ३, १०; ५. २७, १; २; ६०, ८; ६. ७, ३–५; ८, ६; ७; ७. ५, ३; ४; ८; ९; १३, २; ३.
वैश्वानरः १. ५९, ६; ७; ९८, १; २; ३. २, ११; १२; २६, ३; ४. ५, २; ५. ५१, १३; ६. ७, ७; ८, २; ३; ९, १; ७; ७. ५, १; २; ६, ६; ७; ४९, ४; १०. ४५, १२.
वैश्वानरं ३. ३, ५; २६, १; २; ६. ७, १; २; ८, ४; ७. ५, ५; ९. ६१, १६; १०. ८८, १२–१४.
वैश्वानरस्यं १. ९८, १; ३. ३, ११; ६. ७, ६.
वैश्वानराः ३. ३०, ४.
वैश्वानरायं १. ५९, ४; ३. २, १; ३, १; ४. ५, १; ६. ८, १; ७. १३, १.
वैश्वानरे १. ५९, ३.
वोच १. १३२, १; ६. ५९, १.
वोचंः ६. २, ११.
वोचः १. २७, ४; ४. ५, १२; ६. १८, ३; २२, ४; ७. १, २२; ६२, २; ८६, ४; ८. ७५, २; १०. २८, ५.
वोचंत् २. ५, ३.
वोचत् १. ११७, २२; १६४, १८; ३. ५४, ५; ४. ५, ३; ६. १५, १०; ७. ८७, ४; १०. १०, ६; १२, ८; ८८, १७; ११४, ७; १३९, ६.
वोचत २. २१, २; २७, ६; ८. २०, २६; २४, २०; २७, १०; ३०, ३; ३२, १; ४५, २५; ४८, १४; ५२, ९; ६७, ६; १०. ४०, ११; ६३, ११; ११३, ९; १२८, ४.
वोचतं ७. ८३, २.
वोचतात् ५. ६१, १८.
वोचति १. १०५, ४; १२३, ३; १०. ११, २; १६, ११.
वोचतु ३. ५४, १९.
वोचन् ४. १, १४; १०. ६९, ९.
वोचंत ५. ५२, १६.
वोचंत ५. ५२, १६[२].
वोचं १. ३२, १; ५९, ६; १२९, ३; १३६, ६; १५४, १; १६४, २६;

२. १५, १; २१, ३; ३. १, २०; ५. ३१, ६; ४१, १४; ८५, ५; ६. ८, १; ५२, १४; ७. ९८, ५; ८. १०१, १५; १०. ६९, ५; ९३, १४; ११२, ८.

वोचाति १०. ७५, १.

वोचाम १. १६६, १; २. ३०, ७; ३. ५५, १८; ४. ३२, १०; १०. ७२, १.

वोचावहै १. २५, १७.

वोचें ५. ४९, ४.

वोचे १. ४१, ८; १५०, १; ४. ५, ११; ६. ५१, ३; ७. ३३, १; ७३, २; ८. ८४, ५.

वोचेः १. १६५, ३.

वोचेः १. १३२, ३; ७. ९३, ७.

वोचेतं १. १२०, ३.

वोचेमं १. ४३, १; ७५, २; ७. २८, ५.

वोचेम १. ४०, ६; ७४, १; २. ३५, २.

वोचेमहि १. १६७, १०.

वोचेय १. १२२, ५; ४. १, १९.

वोचेयं १०. ९१, १३.

वोचेयं १. १२९, ६.

वोचेयुः १. ४, ६.

वोळहं ८. ५, १०.

वोळहं २. ४१, ९; ८. ३५, ४.

वोळहंवे १. ४५, ६; १३४, ३^{२}; ३. २९, ४; ४. ९, ६; ५. १४, ३; ५६, ६^{२}; ६. ६०, १२.

वोळहा ६. ६४, ३; ८. २, ३५; ९. ८१, २; ९६, १५; ११२, ४.

वोळहा ७. ६९, १; ७१, ४.

वोळहां ८. ३२, २९.

वोळहुः १. १४४, ३.

व्यचः १. ३०, ३; ५२, १४; १०. ९२, ४.

व्यचस्वतीः २. ३, ५; १०. ११०, ५.

व्यचस्वंता ६. २५, ६; १०. १०५, ५.

व्यचिष्ठं २. १०, ४.

व्यचिष्ठे ५. ६६, ६.

व्युत ९. ६९, ५; ७०, २; ८६, ३२.

व्यतींन् १. १५५, ६; ८. ६९, १३.

व्यतींनां ४. ३२, १७.

व्यथते ५. ३७, ४; ५४, ७; ६. ५४, ३.

व्यथंते १०. १०७, ८.

व्यथमानां २. १२, २.

व्यथय ६. २५, २.

व्यथिः ४. ४, ३; ५. ५९, २; ६. २८, ३; ६२, ३; ८. ४५, १९; १०. ३१, १०; ८६, २.

व्यथेते इति ३. ५४, ८.

व्यंतः १. १२७, ५^{२}; ४. ५, ५; ६. १, ४; ७. २७, ५.

व्यंता १. १२२, ४.

व्यंति ५. २३, ३.

व्यंति १. १०५, ७.

व्यंतु २. ११, १५; ५. ४६, ८; ७. १९, ६.

व्यंतु ३. ८, ७; ५. ४६, ८; ७. १, १८; ५७, ६.

व्ययति ७. ८१, १.

व्ययस्व ३. ५३, १९; १०. १६, ७.

व्ययेयं २. २९, ६.

व्यश्वऽवत् ८. २३, २३; २४, २२; २६, ९; ९. ६५, ७.

व्योमऽसत् ४. ४०, ५.

व्रजः ३. ३०, १०.

व्रजनं ७. ३, २.

व्रजंतीः ३. ५६, ४.

व्रजं १. १०, ७; ९२, ४; १३०, ३; १३२, ४^{२}; १५६, ४; २. ३८, ८; ४. १, १५; १६, ६; २०, ८; ५. ३३, १०; ४५, ६; ६. ४५, २४; ६६, ८; ८. ६, २५; २४, ६; ३२, ५; ९. ७७, ४; ९४, १; १०२, ८; १०८, ६; १०. ४, २; २५, ५; २६, ३; २८, ७; ४०, ८; ९७, १०; ९९, ११; १०१, ८.

व्रजस्यं १. १३१, ३; ४. ५१, २; ६. १०, ३; ६२, ११.

व्रजा ५. ६, ७.

व्रजाऽइव ५. ६४, १.

व्रजान् ४. ३१, १३; ६. ७३, ३.

व्रजिनीः ५. ४५, १.

व्रजे १. ८६, ३; ५. ३४, ५; ७. २७, १; ३२, १०; ८. ४१, ६; ४६, ९; ५१, ५; ७०, ६.

व्रतऽचारिणः ७. १०३, १.

व्रततेःऽइव ८. ४०, ६.

व्रतऽनीः १०. ६५, ६.

व्रतऽपाः १. ८३, ५; ३. ४, ७; ५. २, ८; ६. ८, २; ८. ११, १.

व्रतऽपां १. ३१, १०; १०. ६१, ७.

व्रतं १. २५, १; ३१, २; ९३, ८; १०१, ३; १२८, १^{२}; १३६, ५^{२}; १४४, १; १६६, १२; २. ८, ३; २४, १२; ३८, ३; ६; ९; ३. ४, ७; ५९, ३; ६१, १; ४. १३, २; ५. ६९, १; ७. ५, ४; ८. ४०, ८; ४१, ३; ७; ९. ७३, ३; ८२, ५; १०. १२, ५; ३३, ९; ३७, ५; १२२, २; १६६, ४.

व्रतस्यं ७. ६६, ६.

व्रता १. ६६, ५; ६२, १०; ६५, २; ६९, ४; ७०, १; ९०, २; २. ५, ४; २७, ८; ३३, ७; ३. ६, ५; ७, ७; ५५, १; ५६, १; ६०, ६; ५. ६३, ७; ६७, ३; ६. १५, ९; ८. २५, १७; ३२, २८; ४१, १०; ६७, १३; ९४, २; ९. ३५, ४; १०. ६५, ११; ६६, ९; १११, ४.

व्रताऽइव ५. ६६, २.

व्रतानि १. २२, ६; १९; २४, १०; ८४, १२; ९१, ३; ९२, १२; १२४, २; १८३, ३; २. २८, ८; ३. ३, ९; ३२, ८; ५५, ६; ४. ५३, ४; ५. ६९, ४; ६. ७, ५; ८, २; ७. ६, २; ३१, ११; ४७, ३; ७५, ३; ७६, ५; ८३, ९; ८७, ७; ८. २५, १६; ४२, १; ४८, ९; १०३, १; ९. ५३, ३; ७०, ४; ११२, १; १०. २, ४; १०, ५; २५, ३.

व्रतायं २. २३, ६; ३. ३०, ४.

व्रते १. २४, १५; ३१, १; १२; ८३, ३; १०१, ३; २. २८, २; ३८, २; ३. ३८, ६; ५. ४६, ७; ८३, ५^{२}; ६. ५४, ९; ९. ९, ५; ३५, ६; ८६, ३७; १०२, ५; १०. ३६, १३; ५७, ६; ६०, ४; ६४, ५.

व्रतेनं १. १६३, ३; ३. ५९, २; ५. ७२, २; १०. १३, ३.

व्रतेभिः ७. ३५, ९.
व्रतेषु ३. ५४, ५; ९. ६१, २४; ६९, १; १०. ११४, २.
व्रतैः ४. ५३, ५; ६. १४, ३; ८. १, २७.
व्रत्याः ८. ४८, ८.
व्रन् ४. ५, ८.
व्रन् ४. २, १६; ५५, ६; ५. २९, १२.
व्रंदिनः १. ५४, ४; ५.
व्रयः २. २३, १६.
व्राः १. १२४, ८; १२६, ५; ४. १, १६; ८. २, ६; १०. १२३, २.
व्राजऽपतिं १०. १७९, २.
व्राणाः १. ६१, १०.
व्रातः १०. ३४, ८.
व्रातं १०. ५७, ५.
व्रातंऽव्रातं ३. २६, ६; ५. ५३, ११.
व्रातऽसहाः ६. ७५, ९.
व्रातस्य १०. ३४, १२.
व्राताः ९. १४, २.
व्रातासः १. १६३, ८.
व्राधतः १. १००, ९; १२२, १०; १०. ४९, ८; ६९, १०; ९९, ९.
व्राधंत ५. ६, ७.
व्राधंतः १. १३५, ९; १०. ८९, १५.
व्राधंतं ४. ३२, ३; १०. ६९, ११.
व्राधन्ऽतमः १. १५०, ३.
व्रां १. १२१, २.
व्रिशः १. १४४, ५.

श

शंस ३. ४९, १; ७. ३१, २; ६१, ४.
शंस १. ३७, ५; ४. ३, ३; ५. ५२, ८.
शंसः १. १८, ३; ९४, ८; १७८, ४; २. २६, १; ३४, ६; ६. २४, २; ७. ३५, २[2]; १०. ३१, १; ६४, १०.
शंसत ६. ३३, ५.
शंसत १. २१, २; ८. १, १[2]; ३२, १७; १०. ३७, १.
शंसति १०. ४४, ८.
शंसते ५. ४२, ७; ६. ६२, ५.
शंसन् ४. ५१, ७; ९. ९७, २; १०. ६७, १; ११३, १०.
शंसंतः ३. ४, ७; ६. २९, ४; १०. ६७, २.
शंसंतं २. १२, १४; २०, ३.
शंसंति ६. ६७, १०.
शंसंति ३. ३, ८; ५. ७७, १; ७. १९, ९.
शंसंती १०. ८५, ९.
शंसं १. २७, १३; ३३, ७; १२२, ५; १४१, ६; ११; १६६, १३; १८३, ४; २. २०, ७; ३१, ६; ३. १८, २; ४. ६, ११; ५. ४१, ९; ४६, ३; ७. २५, २; ३४, १२; ५६, १९; ८. ३९, २; १०. ४२, ६; ९३, ११; ११३, ३.
शंसय १. २९, १–७.
शंससि २. ४३, २.
शंसा १. १८५, ९; ४. ४, १४.
शंसाः ७. २५, ३; ८. ५७, ३; १०. ७८, ३.
शंसात् १. १२८, ५; १६६, ८.
शंसाति ४. ६, ११; १६, २.
शंसामः १. ६०, ५.
शंसामि ४. ३२, २२; १०. १२४, ३.
शंसामि ७. १००, ५; ८. २७, १५.
शंसाव ३. ५३, ३.
शंसि २. ४, ८; १०. १४८, ४.
शंसिषः १. ८४, १९.
शंसिषं ६. ४८, १६; १०. ४४, ५.
शंसिषं ६. ४८, १; ८. ४५, २८; १०. ९६, १.
शंसे ३. १६, ४.
शंसेन १०. ७३, २.
शंसैः १. १७३, ९; १०; १०. ७, १.
शंस्ता १. १६२, ५.
शंस्यं १. १०, ५; ११६, ११; ११७, ६; २. ३४, ११; ५. ३९, ५; ६. २६, ३; ७. १९, ८; ८. १८, २१; ६०, ११; ८३, ४; १०. ४७, २; ४८, ९.
शंस्या १. ८, १०; ८. ६३, २.
शंस्यानां १. १७, ५.
शकः ८. ८०, ३.
शकः ७. २०, ९.
शकटीःऽइव १०. १४६, ३.
शकंत् ८. ९१, ४.
शकत् १. १०, ६; ८. ३२, १२; १०. ४३, ५.
शकऽपूते १०. १३२, ५.
शकऽमयं १. १६४, ४३.
शकुनः ४. २६, ६; ९. ८६, १३; ९६, १९; २३; १०. १६, ६; १६५, २.
शकुनं ९. ८५, ११; १०. १२३, ६.
शकुनस्य १०. ६८, ७.
शकुनस्यऽइव १०. १०६, ३.
शकुनाःऽइव ९. १०७, २०.
शकुनानां ९. ११२, २.
शकुने २. ४२, १; ४३, २[3]; ३.
शकुंतयः २. ४३, १.
शकुंतिका १. १९१, ११.
शकुंते २. ४२, ३.
शकृत् १. १६१, १०.
शकेम १. ७३, १०; ९४, ३; २. ५, १; ३. २७, ३.
शक्तं ५. ६८, ३; ७. ६७, ५; ६८, ८; १०. ४०, ५.
शक्तिः १. ८३, ३; ४. २२, ८; ७. २०, १०.
शक्तिऽभिः १०. २५, ५; ८८, १०.
शक्ति १०. १३४, ६.
शक्तिं २. ३९, ७; ३. ५७, ३; ४. ४३, ३.
शक्तिऽवः ५. ३१, ६.
शक्तिऽवंतः ६. ७५, ९.
शक्ती १. ३१, १८.
शक्ती ७. ६८, ८.
शक्तीः १. १०९, ३; ३. ३१, १४.
शक्रवाम १. २७, १३; १०. २, ३.
शक्म २. ३८, ४.
शक्मना ९. ३४, ३; ६२, १६; ११०, ३.
शक्मऽभिः ९. ७, ८.
शक्यां १०. २९, ३.
शक्र १. ६२, ४; १०४, ८; १७७, ४; ३. ३५, १०; ३७, ११; ६. ३५, ५; ७. २०, ९; ८. ४, १५;

१२, १७; १३, १५; ४५, १०; ५२, १; ९२, ११; २६; ९७, १४; १०. ३८, २; ४२, ३; १३४, ३.

शक्रः १. १०, ५; ६; ४. १६, ६; ५. ३४, ३; ४; ७. १०४, २०; २१; ८. १, १९; ३१, २; ३२, १२; ६६, ३; ६९, १४; ७८, ५; ९३, १८; १०. ४३, ६; १०४, १०.

शक्रं ६. ४७, ११; ८. ५०, १; १०. १६७, २.

शक्रा ५. ४१, १५.

शक्रा २. ३९, ३; १०. २४, ४.

शक्राः १. १६६, १.

शक्राय १. ५४, २; ८. २, २३; ९१, १.

शर्करीषु ७. ३३, ४; १०. ७१, ११.

शग्धि १. ४२, ९; ३. १६, ६; ५. १७, ५; ८. ३, ११[२]; १२[२]; २४, ११; ६१, ५; १३; ९. ८९, ७; १०. १४७, ५.

शग्धि २. २, १२; ४. २१, १०.

शग्मः ६. ४४, २.

शग्मं ६. ७५, ८.

शग्मया ७. ५४, ३.

शग्मा ८. २, २७.

शग्मां ५. ४३, ११.

शग्मासः ७. ६०, ५; ९७, ६; १०. ३१, ५.

शग्मैः १. १३०, १०; १४३, ८.

शग्म्येन ३. ३१, १.

शंकवः १. १६४, ४७.

शचिष्ठ ८. ६६, १४.

शचिष्ठः ४. २०, ९.

शचिष्ठया ४. ३१, १.

शचिष्ठा ४. ४३, ३.

शचीनां १. १७, ४; ४. ४३, ३; ८. ३२, १५.

•शचीनां १०. २४, २.

शची३ऽपतिः ४. ३०, १७.

शची३ऽपतिं १. १०६, ६; ८. १५, १३.

शचीपती इति शचीऽपती ७. ६७, ५.

शचीऽपते ८. १४, २; १०. २४, २.

शचीऽपते ४. ३१, ७; ६. ४५, ९; ८. ३७, १; ६१, ५; ६२, ८.

शचीभिः १. ३०, १५; ६२, १२; १०३, २; १०९, ७; ११२, ८; ११६, २२; २३; ११७, १३; २०; ११८, ६; १३९, ५; १६४, ४४; ३. ६०, २; ४. ३०, ६; ४४, २; ६. ४४, ९; ४५, २४; ४७, १५; ७. ६, ४; ६७, ५; ६८, ८; ६९, ४; ९२, २; ८. २, १५; ३२; १६, ७; ५३, ६; ५७, १; ४; १०. २२, १४; ३९, १३; ८९, ४; १३१, ५; १३४, ३; १३९, ३; १५७, ५.

शचीऽवः १. २९, २; ५३, ३; ८. २, २८; ६८, २; १०. ७४, ५.

शचीऽवः १. ६२, १२; ३. २१, ४; ५३, २; ६. ३१, ४; ८. २, १५; ९. ८७, ९; १०. ४९, ११; १०४, ४.

शचीऽवतः ६. २४, ४.

शचीऽवते १. ५४, २.

शचीवसू इति शचीऽवसू १. १३९, ५; ७. ७४, १.

शचीवसो इति शचीऽवसो ८. ६०, १२.

शचीऽवान् ४. २२, २; ८. २, ३९.

शच्या ३. ६०, ६; ४. २०, ९; ३५, ५[३]; ५६, ३; ६. १७, ६; २६, ६; ३१, ४; ४४, २४; ८. ९६, १३; १७; १०. ६१, ३; १०४, ३.

शच्या १०. ६१, १.

शंडिकानां २. ३०, ८.

शतऽअनीकाः ८. ५०, २.

शतऽअरित्रां १. ११६, ५.

शतऽअर्चसं ७. १००, ३.

शतऽअवयं ५. ६१, ५.

शतऽअश्रि ६. १७, १०.

शतऽअश्वं ८. ४, १९; १०. ६२, ८.

शतऽआत्मा १. १४९, ३; १०. ३३, ९.

शतऽआत्मानं ९. ९८, ४.

शतऽआयुषं ६. २, ५.

शतऽआयुषा १०. १६१, ३; ४.

शतऽऊतिः ७. ६८, ३.

शतऽऊतिं ६. ६३, ५.

शतऽक्रतुः २. २२, ४; ४. ३०, १६; ८. १, ११; ३२, ११; ७७, १; ८९, ३; ९३, ३२.

शतऽक्रतुं १. ३०, १; ५१, २; ३. ५१, २; ८. ५२, ६; ५३, २; ६१, १०; ९२, १; ९९, ८.

शतक्रतू इति शतऽक्रतू १. ११२, २३.

शतक्रतो इति शतऽक्रतो ६. ४१, ५; ८. ४६, ३.

शतक्रतो इति शतऽक्रतो १. ४, ८; ९; ५, ८; १०, १; १६, ९; ३०, ६; १५; ५४, ६; ८२, ५; १०५, ८; २. १६, ८; ३. ३७, २; ३; ६; ९; ४२, ५; ५. ३५, ५; ३८, १; ५; ६. ४५, २५; ७. ३१, ३; ८. १३, ३१; ३३, ११; १४; ३६, १; ५२, ४; ५४, ८; ६१, ९; १८; ७६, ७; ८०, १; ९१, ७; ९२, १२; १३; १६; ९३, २७–२९; ९८, १०–१२; १०. ११२, ६; १३४, ४.

शतऽक्रत्वः १०. ९७, २.

शतऽग्विनः ८. ४५, ११.

शतऽग्विनं १. १५९, ५; ४. ४९, ४; ९. ६५, १७; ६७, ६.

शतऽचक्रं १०. १४४, ४.

शतऽतमं ४. २६, ३.

शतऽतमा ७. १९, ५.

शतत्ऽवसुं १. ११९, १.

शतऽदातु ९. ७२, ९.

शतऽदायं २. ३२, ४.

शतऽदाम्नि ५. २७, ६.

शतऽदुरस्य १०. ९९, ३.

शतऽदुरेषु १. ५१, ३.

शतऽधन्यं ४. १८, ३.

शतऽधारः ९. ८५, ४; ८६, ११; ९६, १४.

शतऽधारं ३. २६, ९; १०. १०७, ४.

शतऽधाराः ९. ८६, २७.

शतऽनीथः १. १००, १२; १०. ६९, ७.

शतऽनीथं १. १७९, ३.

शतपत्ऽभिः १. ११६, ४.

शतऽपत्रः ७. ९७, ७.

शतऽपर्वणा १. ८०, ६; ८. ६, ६; ७६, २; ८९, ३.

शतऽपवित्राः ७. ४७, ३.

शतऽब्रध्नः ८. ७७, ७.
शतऽभुजिः ७. १५, १४.
शतऽभुजिभिः १. १६६, ८.
शतं १. २४, ९; ३०, २; ४८, ७; ५२, १; ६४, १४; ८९, ९; ११६, ७; १६; ११७, ६; १७; १८; १२६, २[३]; १२८, ३; २. १३, ९; १४, ६[२]; ७; २७, १०; ३३, २; ३. ३६, १०; ६०, ७; ४. २७, १; ३०, २०; ३१, ३; ९; १०; ३२, १७; ४८, ५; ५. २७, ५; ४८, ३; ५४, १५; ६१, १०; ६. १७, ११; ३४, ३; ४७, २४; ४८, ८[२]; ६३, ९; ७. ३, ७; १६, १०; २५, ३; ६६, १६[२]; ९१, ६; ९९, ५; ८. १, २४; ५, ३७; ६, ४२; ४६; २१, १०; ४६, ३१; ३२; ५५, २; ३[४]; ५६, ३[२]; ७०, ५[२]; ७७, १०; ९. ४८, २; ५२, ५; ५६, २; ६१, २७; ९७, २९; १०. १८, ४; २९, २; ८५, ३९; ९७, १; २; १०३, १; १०५, ११; १५८, २; १६१, ३; ४[४].
शतंऽमघ ८. ३४, ७.
शतऽमघ ८. १, ५.
शतऽमघः ८. ३३, ५; ९. ६२, १४.
शतऽमन्युः १०. १०३, ७.
शतंऽऊतिः १. १०२, ६; १३०, ८; ८. २, २६.
शतंऽऊतिं ८. ९९, ८.
शतंऽऊते ८. ४६, ३.
शतंऽऊते ७. २१, ८.
शतंऽऊतेः ८. २, २२.
शतऽयातुः ७. १८, २१.
शतऽयाम्ना ९. ८६, १६.
शतरां १०. १०६, ५.
शतऽवत् ८. २४, २९; १०. ९४, २; १०२, ५; ९.
शतऽवन् ६. ४७, ९.
शतऽवंतं ८. ५, १५; ६४, ५.
शतऽवल्शाः ३. ८, ११.
शतऽवाजः ९. ९६, ९; ११०, १०.
शतऽवाजया ८. ९२, १०.
शतऽविचक्षणाः १०. ९७, १८.
शतऽव्रजाः ४. ५८, ५.
शतऽशारदाय ७. १०१, ६; १०. १६१, २.
शतऽशारदेन १०. १६१, ३.
शतऽसाः ४. ३८, १०; ७. ८, ६; ९. ८२, ५; ८७, ४; १०. ९५, ३; १७८, ३.
शतऽसेयाय ३. १८, ३.
शतस्यं १. ४३, ७.
शतस्वी ७. ५८, ४.
शतऽहिमा २. १, ११.
शतऽहिमाः १. ७३, ९; ६. ४, ८.
शतऽहिमाय ९. ७४, ८.
शता १. ५३, ८; ८०, ९; ८१, ७; १२२, ७; १२६, ६; २. १, ८; ३. ९, ९; ४. ३०, १५; ३२, १८; ५. २७, २; २९, ८; ५२, १७; ६२, १; ६. २६, ५; ४७, १८; ४८, १५; ६३, १०; ७. १८, १४; ३२, ५; ८. ३२, १८; ४५, १२; ४६, २२[२]; ३१; ७८, १; १०. ९३, १४.
शतात् १. १०२, ७.
शतानि १. १६४, ११; ४. २९, ४; ५. २९, ७; ६. ३१, ४; ७. १०३, १०; ८. ६, ४७; ३४, १५; ६१, ८.
शतानीकाऽइव ८. ४९, २.
शतार्य ८. १, ५.
शतिनः १. ३१, १०; ७. ५७, ७; ८. १, ९; ७५, ४.
शतिनं १. ६४, १५; १२४, १३; २. २, ९; ६. ८, ६; ८. ८८, २; १०. ४७, ५.
शतिनीभिः १. ५९, ७; १३५, १; ३.
शते इति ७. १८, २२.
शतेन २. १८, ६; ३. ३७, ४; ४. ४६, २.
शतैः ५. ३६, ६; ६. २०, ४.
शत्रवः १. ५, ४; ६. १४, ४; ७. १८, १८; १०. ३८, ३; ४८, ७; ८४, ७; १५५, ४.
शत्रवे १०. १३३, ३.
शत्रि ५. ३४, ९.
शत्रुः १. ३९, ४; १२९, ४; ६. १८, १२; ७. २१, ६; ८. ५९, २; ९६, १६; १०. ४२, ६; १२०, २.
शत्रुऽतूर्याय ६. २२, १०.
शत्रुऽत्वं ८. ४५, ५.
शत्रुं १. ३२, ४; ३३, १२; १२९, ४; १७६, १; २. २३, ११; ३०, ३–५; ३. १६, २; ६. ४६, १०; ७. ३४, १९; ९. ५५, ४; ७८, ५; १०. ४२, ७; ५४, २.
शत्रुऽयतां १. ३३, १५; ५. ४, ५; २८, ३.
शत्रुऽयंतः १०. ८९, १५.
शत्रुऽयंतं ७. २०, ३.
शत्रुषु ९. १९, ६.
शत्रुऽसहः ८. ६०, ६.
शत्रुऽहनः १०. १५९, ३.
शत्रूणां १. १०२, ४; १०. १६६, १.
शत्रून् १. ३३, १३; ६१, १३; १३२, ६; १४३, ५; १७८, ५; २. ३०, ८; ९; ४१, १२; ३. ३०, ६; ३४, १; ४७, २; ५४, २२; ४. ४, ५; २८, ४; ४१, २; ६. १७, ३; १९, ८; ४४, १७; ४७, २९; ६४, ३; ७३, २; ७५, ४; ७; ८. ३५, १२; ९. ८५, २; ९०, ३; ९४, ५; ९६, २३; ११०, १२; १०. ४२, ५; ६९, ११; ८३, ३; ८४, २; ३; १०७, ११; ११२, १; ५; ११६, ३; ५; १२०, १; १३८, ४; १८०, १; २.
शत्रोः १. ५१, ७; १६५, ६; ६. ७५, २; ७. ४८, ३; ९. १९, ७.
शत्रोःऽशत्रोः ६. १९, १३.
शनकैःऽइव ८. ९१, ३.
शनैः ८. ४५, ११.
शनैःऽइव ८. ९१, ३.
शंतातिऽभिः १०. १३७, ४.
शंताती इति शंऽताती १. ११२, २०.
शपथाः १०. ८७, १५.
शपथ्यात् १०. ९७, १६.

शर्पंतं १. ४१, ८.
शर्पांतः १०. ८७, १३.
शुफुऽआरुजंः १०. ४४, ९.
शुफुऽआरुजं १०. ८७, १२.
शुफऽच्युतः १. ३३, १४.
शुफं ८. ४७, १७.
शुफऽवंत् ३. ३९, ६; ५. ८३, ५.
शुफात् १. ११६, ७; ११७, ६.
शुफानां १. १६३, ५; ५. ६, ७.
शुफौऽइंव २. ३९, ३.
शुबलौं १०. १४, १०.
शं १. ५, ७; ४३, ६; ९०, ९[५]; ९३, ७; १०६, ५; ११४, १; २; १५७, ३; १६५, ४; १७३, ८; १८९, २; २. ३३, १३; ३८, ११; ३. १३, ६; १७, ३; १८, ४; ४. १, ३[२]; १२, ५; ५. ७, ९; ११, ५; ४७, ७; ५०, ५[३]; ५३, १४; ६९, ३; ७४, ९; ६. २१, ४; ३४, ३; ४५, २२; ५०, ७; ७४, १[२]; ७. ६, २; ३५, १[५]; २[६]; ३[६]; ४[५]; ५[४]; ६[४]; ७[७]; ८[५]; ९[६]; १०[४]; ११[६]; १२[५]; १३[५]; ३८, ७; ५४, १; ६९, ५; ८६, ८[२]; ८. ५, २०; १३, ११; १७, ६; १८, ८; ९[३]; ३९, ४; ४८, ४; ७१, १५; ७९, ७; ८२, ३; ९. ११, ३[४]; ७; ६०, ४; ६१, १५; ६९, ७; ९१, ६; १०९, ५; १०. ९, ४[२]; १५, ४; ३७, १०[७]; ११; ५९, ८; ८६, १५; ९७, १८; १६५, १[२]; ३; १८२, १.
शर्मे १. ३३, १५.
शमस्य १. ३२, १५.
शुंऽआयुते ८. ८६, ५.
शुंऽआये ३. १, १.
शुंऽगुयः २. १, ६.
शुंऽगयीं ९. ९७, १७.
शंऽतंनवे १०. ९८, १; ३; ७.
शुंऽतुम ८. ५३, ५.
शंऽतंमः १. १६, ७; ७७, २; १२८, ७; १३६, ४; ८. १३, २२; ९. १०४, ३.
शंऽतंमं १. ४३, १.
शंऽतमा १. ७६, १; २. ३३, १३; ३. १३, ४; ५. ४२, १; ४३, ८; ७३, १०; ८. ३३, १५; ७४, ८; १०. ५३, ९.
शंऽतंमानि ६. २३, ६; ३२, १.
शंऽतंमाभिः ८. ५३, ५.
शंऽतंमेन ५. ७६, ३; ७८, ४; ७. ५१, १; १०. १५, ४.
शंऽतंमेभिः २. ३३, २.
शंऽतांति ८. १८, ७.
शर्मि १. ८७, ५; २. ३१, ६; ३. ५५, ३; ८. ४५, २७; १०. ४१, १.
शुमिता २. ३, १०; ३. ४, १०; १०. ११०, १०.
शुमिताऽइंव ५. ८५, १.
शुमितारंः १. १६२, १०.
शुमितारा ५. ४३, ४.
शुमितुः १. १६२, ९.
शमीं १. ११०, ४; ४. २२, ८; ९. ७४, ७.
शुमीनहुषी इतिं १०. ९२, १२.
शमींभिः १. २०, २; ३. ६०, ३; ४. १७, १८; ३३, ४; ५. ७७, ४; ६. ३, २; ५२, १; १०. २८, १२.
शमीं ५. ४२, १०; ८. ७५, १४.
शंबः १०. ४२, ७.
शंबरं १. ५१, ६; ५४, ४; ५९, ६; १०१, २; १३०, ७; २. १२, ११; ४. ३०, १४; ६. १८, ८; २६, ५; ४३, १; ४७, २१; ७. १८, २०; ९. ६१, २.
शंबरस्य १. १०३, ८; २. १४, ६; १९, ६; ४. २६, ३; ६. ३१, ४; ४७, २; ७. ९९, ५.
शुंबुरऽहत्ये १. ११२, १४.
शंबराणि २. २४, २.
शंऽभंविष्ठः १. १७१, ३; ४. ४३, २; ५. ४२, ७; ९. ८८, ३.
शंऽभंविष्ठा २. ३९, ५; ५. ७६, २; ६. ६२, ५.
शंऽभंविष्ठाः १०. ७७, ८.
शुंऽभु १. ६५, ३; १०. १८६, १.
शुंऽभुः ३. १७, ५; ७. ३५, १०.
शुंऽभुवंः १. १०५, ३; १०६, २.
शुंऽभुवं १. ४०, ६; १०. ३६, ७.
शुंऽभुवा २. ४१, १९; ६. ६०, १४; ८. ८, १९.
शुंऽभुवा ६. ६०, ७.
शुंभू इतिं शुंऽभू ४. ४१, ७.
शुंभू इतिं शंऽभू १. ४६, १३.
शम्यां १. ८३, ४; २. १, ९.
शम्यांः ३. ३३, १३.
शुम्यां १०. ३१, १०.
शुंयू इवेतिं शुंयूऽइंव १०. १४३, ६.
शम्यै ४. ३, ४.
शुंऽयोः १. ३४, ६; ४३, ४.
शुयुते १. ३२, ५; ८. १००, ९.
शुयथां १०. ६७, ५.
शुयथांय ६. १८, ८.
शुयथें ६. १७, ९.
शुयध्यै २. १७, ६; ६. ६२, ३.
शुयुध्वे १०. १०८, ४.
शयंते १०. ८९, १४.
शुयवें १. ११२, १६; ११६, २२; ११७, २०; ११८, ८; ६. ६२, ७; ७. ६८, ८; १०. ३९, १३.
शुयुाते इतिं ७. १०४, १३.
शयांनं १. ३२, ८; २. १२, ११; ३. ३२, ६; ५. ३२, २; ६; ८; ७. १०३, २; ८. ५१, २; १०. १०२, ९.
शयांना ४. ३३, ३.
शुयासुं ३. ५५, ४.
शयींत १०. ९५, १४.
शुयुः १. ३१, २; ३. ५५, ६.
शुयुऽत्रा १. ११७, १२; १०. ४०, २.
शुयुं ४. १८, १२; १०. ४०, ८.
शयें ३. ५५, ४; १०. ४, ४; १६२, ४.
शुये १. ३२, ९; १४०, ७; १४१, २; १६४, ३०; ४. ३०, ११.
शुयोः १. ११९, ६.
शारें ८. ७०, १४.
शुरुणं १. १५८, ३; २. ३, ८; ६. ४६, ९; ४९, ७; ५०, ३; ७. ९५, ५; १०१, २; ८. ४७, १०.

शरणा ६. ४७, ८; ८. ९०, ६.
शरणाः १०. १८, १२.
शरर्णि १. ३१, १६.
शरणे १. १५०, १; ७. १९, ८; ८. २५, १९.
शरणैः ३. ६२, ३.
शरत् १०. ९०, ६.
शरत्ऽभिः १. ८६, ६; २. २४, ५.
शरत्ऽवान् १. १८१, ६.
शरदः १. ७२, ३; ८९, ९; १७३, ३; १७९, १; २. २७, १०; ३. ३२, ९; ३६, १०; ४. १६, १९; १८, ४; १९, ८; ५. २, २; ६. २४, ७; ३८, ४; ३९, ३; ४७, १६; ७. ३७, ७; ६१, २; ६६, १६[२]; ९१, २; १०. १८, ४; ८५, ३९; ९५, १६; १६१, ३; ४.
शरदः ७. ६६, ११.
शरदि २. १२, ११.
शरभार्य ८. १००, ६.
शर्वः १०. ८७, १५.
शर्वे ४. ३, ७; ६. २७, ६; १०. २७, ६; १२५, ६; १८२, ३.
शरव्या १०. ८७, १३.
शरव्ये ६. ७५, १६.
शरस्य १. ११६, २२; ८. ७०, १३.
शरारुः १०. ८६, ९.
शरासः १. १९१, ३.
शरीतोः ३. ५३, १७.
शरीरं १. ३२, १०; १६३, ११; १०. १६, १.
शरीरा १०. १३६, ३.
शरीरैः ६. २५, ४; १०. १६, ३; ९९, ८.
शरुः १. १७२, २; १८६, ९; ८. ६७, १५; २०.
शरु ७. ७१, १; ८. १८, ११; १०. ९९, ७.
शरुऽमान् १०. ८९, ५.
शर्ध ५. २८, ३.
शर्धः १. ३७, १; ५; १०६, १; १२७, ६; १३३, ३; १३९, १; २. १, ५; ६; ३, ३; ११, १४; ३. १९, ४; ३२, ४; ४. १, १२; ६, १०; ५. ३३, ५; ४२, १५; ४६, २; ५; ५२, ८; ५४, ६; ६. ३, ८; ८, ७; ४८, १५; ६८, ८; ७. ४४, ५; ५९, ७; ८. १५, ९; ९. ८८, ७; ९०, ५; ९७, ४२; १०. १०३, ९.
शर्धःऽतरः १. १२९, १०.
शर्धत् ७. २१, ५.
शर्धतः २. २३, १२; ६. २३, २; ४२, ४; ७. १८, १८; ३२, ७; ८. ६०, १२; १०. ६९, १२.
शर्धतां ८. १९, २०.
शर्धते २. १२, १०; ६. २४, ८; ८. २, १५.
शर्धन् ८. ४३, ३२; ९. १००, ८.
शर्धऽनीतिः ३. ३४, ३.
शर्धतः ७. ३४, १८.
शर्धतं २. ३०, ८; ५. ५६, १; ७. १८, ५; १६.
शर्ध १. ७१, ८; १२२, १२; २. ३०, ११; ५. ५३, १०; ५६, ९; ८. ९३, १६.
शर्धऽशर्ध ५. ५३, ११.
शर्धस्य ७. ५६, ८.
शर्धान् ८. ७, २१.
शर्धासि ५. ८७, ७; १०. ९१, ७.
शर्धासिऽइव ८. ७४, १३.
शर्धाय १. ३७, ४; ६४, १; १११, २; ४. ३, ८; ५. ५४, १; ८७, १; ६. ४८, १२; ६६, ११; ८. २०, ९; ९. ३०, ६; १०४, ३; १०५, ३; १०. ६१, २५; १४७, ५.
शर्धेन २. ३१, ३.
शर्ध्यै १. ११९, ५.
शर्म १. १७, ८; २१, ६; २२, १५; ३४, ६; ४६, १५; ५८, ८; ९; ८५, १२; ९०, ३; ९३, ८; १०२, ३; १०७, २; ११४, ५; १०; १२७, ५; १३६, ७; १४०, १२; १४२, ५; १७४, २; २. २५, ५; २७, ६; ७; ३. १५, ५; ५४, २०; ४. २५, ४; ५; ५३, ६; ५४, ६; ५५, ४; ५. १, १०; २, १२[२]; २७, २; ४४, ७; ४६, ५; ७; ५५, ९; ६२, ९; ८३, ५; ६. १६, ३३; ३८; २०, १०; ४६, १२; ४९, ७; ५१, ५; ७५, ११; १२; १७[२]; ७. ५, ९; १६, ८; ५२, २; ५९, १; ६०, ८; ८२, १; १०; ८३, ९; १०१, २; ८. १८, ३; १२; १६; २७, ९; ३०, ४; ४२, २; ४७, २; ३; ७; ९; १०; ९. ६१, १०; ६४, १८; ७४, १; ८५, ८; ८६, १५; ९७, ४७; १०. ३६, ४; ३७, ११; ५६, २; ६३, ७; १२; ६६, ३; ५; ७; ८७, १; १०३, १३; १२६, ७; १२८, ८; १४२, १; १५२, ५; १६९, २.
शर्मणा १. २२, ११; ५. ४, ८; ७. ५१, १; ८. १८, १७; ४०, १२.
शर्मणि १. ४, ६; २. २, १२; ३. १५, १; ५. ६४, ३; ८. ४४, १८; ६२, १०; १०. ३५, ९; ३६, १२; १२६, ४; १६७, ३.
शर्मणे ८. ९, २०.
शर्मन् १. ५१, १५; ९४, १३; २. २७, १६; २८, ३; ३. ५१, ७; ४. १७, १९; ५. ३८, ५; ६. ३३, ५; ४९, १३; ७. ६, ६; १८, ३; ३४, २५; ५६, २५; ९५, ५; ८. ६०, ६; १८; १०. ६, १; १२९, १; १३१, १.
शर्मऽयंत्या ९. ४१, ६.
शर्मऽसदः १. ७३, ३.
शर्माणि ३. १३, ४.
शर्यणाऽवतः १०. ३५, २.
शर्यणाऽवति १. ८४, १४; ८. ६, ३९; ७, २९; ६४, ११; ९. ६५, २२; ११३, १.
शर्यऽहा ६. १६, ३९.
शर्यहाऽइव ९. ७०, ५.
शर्याणि ९. १४, ४; ६८, २.
शर्यातं १. ११२, १७.
शर्याभिः ९. ११०, ५; १०. ६१, ३.
शर्या १. १४८, ४; १०. १७८, ३.

शर्यै॑ः १. ११९, १०.

शर्व॑रीः ५. ५२, ३.

शर्वा॑ १. १००, १८; २. १२, १०; ४. २८, ३; ७. ८५, २; १०. ८७, ६.

श॒ल्म॒लिं १०. ८५, २०.

श॒ल्म॒लौ ७. ५०, ३.

श॒ल्यान् १०. ८७, ४.

शव॑ः १. ८, ५; ३७, ९; ३९, १०; ५१, १०; ५२, ६; ७; ५६, ३; ८०, ३; १३; ८१, ४; ८४, ९; १८६, २; २. ११, १८; ३. ३६, ४; ५. ३५, ४; ५८, ७; ८६, ३; ८७, २; ६; ६. १९, ६; ४३, ४; ४८, २१[३]; ७. १०४, ३; ८. ३, ४; ६; ८; १०; २४, ९; ५१, १०; ५६, १; ६२, ८; १०; ७५, १३; ९. ६४, २; १०. २३, २; ५; १४८, ४.

शव॑ःऽभिः १. १३०, ४; ६. १७, १.

शव॑सः १. ५४, १; १००, ८; १५; १४५, १; १६७, ९; ३. ४१, ५; ४. २४, १; ५. १५, ५; २०, २; ५२, २; ६. १४, ४; २९, ५; ४४, ४; ७. २७, १; ८. २५, ५; ६८, ४; ९०, २; १०. २२, ३; ९९, १.

श॒व॒स॒ः १. ११, २; १३१, ४; १६१, १४; ४. ३४, ६; ३५, १; ८; ३७, ४; ४७, ३; ५. ६, ९; ३५, ५; ८. ६, २१; ४५, २०; ९०, ५; ९२, १४; ९७, ६; ९. ३६, ६.

शव॑सा १. २७, २; ३९, ८; ५१, ४; ५२, १०; ११; ५४, २; ५६, ४; ६१, १०; ६२, ९; ६४, ८; ९; १३; ९४, १५; १००, ३; १२; १४; १०२, १; ११०, ७; १२७, ११; १४१, ३; १६७, ९; १७१, ५; २. २२, ४; २३, १५; २४, ११; १४; ३. ३, ९; ४. ८, ८; १६, ७; १७, १; ३; १९, ४; २२, १; ५; ३८, ३०; ५. ७, ३; ११, ५; ३०, ४; ४६, ६; ६. ४, ७; १३, ३; ५; १५, ११; १८, ७; १९, २; २०; १; ७; २९, ३; ३२, ५; ३६, ५; ४४, ३; ६६, ६; ६८, ३; ७. २१, ६; २३, १; ३०, १; ४८, २; ५७, १; ७४, ६; ८५, ४; ९३, २; ८. १, २१; १२, २६; १९, १६; २४, २; १७; ७०, ६; ८८, ४; ९७, ९; १०. ३१, ५; ४३, ४; ४९, ८; ७३, ८; १००, ५; १०५, ६; १२०, २; ६; ९; १४०, १; १७८, ३.

श॒व॒सा॒नं १. ६२, १३; ८. ६८, ८.

श॒व॒सा॒न ६. ३७, ३; ८. ४६, ६.

श॒व॒सा॒ना ७. ९३, २.

श॒व॒सा॒नात् ८. २, २२.

श॒व॒सा॒नाय॑ १. ६२, १; २.

श॒व॒सा॒नेभि॑ः १०. ९९, ९.

श॒व॒सा॒ऽव॒न् १. ६२, ११.

श॒व॒सि॒न् ७. २८, २.

श॒व॒सी ८. ४५, ५; ७७, २.

शव॑से १. ५७, १; ८१, १; ८; १३०, ६; ३. ३७, १; ५. ८७, १; ६. ३४, २; ७. २८, ३; ६६, ८; ८. ९, २०; २४, १२; १०. ४८, ११; ४९, २; ११६, १.

शवां॑सि ६. २५, ३; ७. २१, ९; ४८, २; ५६, ७; ८. २, ३०; ६८, ८; ९७, १३.

शवि॑ष्ठ १. ८०, १; ८४, १; ८. ६६, १२; ६८, १.

श॒वि॒ष्ठ १. ८४, १९; १२७, ११; १६५, ७; ५. २९, १३; १५; ३५, ८; ३८, २; ६. २६, ७; ३५, ३; ७. २१, ५; ८. ६, ३१; १२, १; १३, १२; ३३, १३; ४६, ९; १९; ६२, ४; ७०, ६; १२; ९०, ४; ९७, १४; १०. ११६, १.

शवि॑ष्ठः ८. ६१, १.

शवि॑ष्ठं ५. ४४, १०; ६. १९, ६; २२, २; ७; ८. ४०, २.

शवि॑ष्ठस्य ८. ७४, १४.

शवि॑ष्ठा ६. ६८, २.

शवि॑ष्ठाः १. ७७, ४.

शवि॑ष्ठात् ८. ७४, १५.

शवी॑रया १. ३, २; ३०, १७.

श॒शः १०. २८, ९.

श॒शम॑ते ६. २, ४.

श॒श॒मा॒नः १. २४, ४; १५१, ७; ४. २, ९; २३, ४; ३१, ७; १०. ११, ५.

श॒श॒मा॒नं २. १२, १४; २०, ३.

श॒श॒मा॒नस्य॑ १. ८६, ८; १४२, २; ४. २२, ८; २३, २; ५. ४२, १०; १०. ६४, १०; १४२, ६.

श॒श॒मा॒नाः ५. २९, १२.

श॒श॒मा॒नाय॑ १. ८५, १२; ११३, २०; १४१, १०; ४. २, १३; ३१, ८; ८. ६६, २.

श॒श॒मा॒नास॑ः ४. १६, १५; १०. ९२, ७.

श॒श॒मा॒नेभ्य॑ः ४. ४१, ३.

श॒श॒मा॒नेषु॑ ३. १८, ४.

श॒श॒मे ६. १, ९; ३, २; ८. १०१, १.

श॒श॒यः १. १६४, ४९.

श॒श॒यं ३. ५७, २; ८. ५४, ८.

श॒श॒याः ३. ५५, १६.

श॒श॒या॒नः ५. ७८, ९.

श॒श॒या॒ना ७. १०३, १.

श॒शाः १. ८०, १.

श॒शा॒धि ७. १, २०; २५.

श॒शा॒स २. २९, ५.

श॒शा॒सुः ३. १, २; ४. २, १२.

शशी॑यसी ५. ६१, ६.

शशी॑यांसं ४. ३२, ३.

श॒श्र॒थे ९. ७०, २.

श॒श्र॒मा॒णः ४. १२, २; १०. १०५, ३.

श॒श्र॒मा॒णा १. १७९, १.

श॒श्र॒मुः ९. २२, ४.

श॒श्व॒चै ३. ३३, १०.

शश्व॑त् १. ३०, १६; ३५, ५; ४७, ९; १०; ११३, १३; ११६, ६; १२३, ४; ३. ५४, १; ६. २०, ८; २१, ८; ३२, ३; ४०, ४; ४१, २; ६२, ३; ८. ५, २३; ६७, १६; ७१, १३; ८०, २; ९. ६६, १६; ९७, ५८; १०. ६९, ११; ११२, ५.

शश्व॑तः १. ७२, १; १३५, ७; २. १२,

१०; ३. ३५, ५; ३६, १०; ५. १९, ४; ५२, २; ७. १९, १; ९. ७६, ३; १०. ४८, १.
शश्वंता १. २६, ६; ९. १, ६.
शश्वंतां ४. ३२, १३; ८. २०, १३; १०. १००, ११.
शश्वंती ८. १, ३४.
शश्वंतीः १, २७, ७; ३. ९, ४; ७. ३२, २७.
शश्वंतीनां १. ११३, ८; १५; १२४, २; १७१, ५; ३. ५६, ३; ६. १, ८; ७. १०१, ६; ८. १७, १४; ३९, ५; ९५, ३.
शश्वंतीषु ४. ७, ६.
शश्वतीषु ८. ६०, १७.
शश्वंते १. ३६, १९; ३. ३२, ५; ८. २३, २८; ९. ९८, ४.
शश्वत्ऽतमं २. ३८, १; ३. १, २३; ३५, ६; ६२, २; ९. ८७, ४; १०. ७०, ३.
शश्वत्ऽतमा १. १२४, ४.
शश्वत्ऽतमायाः १. ११८, ११.
शश्वत्ऽतमासः १०. ३९, १.
शश्वत्ऽभिः ७. ९३, ६.
शश्वत्ऽशश्वत् ३. ३६, १.
शश्वधा ३. ३३, ७.
शश्वंतः ५. १४, ३; ७. १, ३; १८, १८; ९४, ५.
शश्वंतं ६. ६१, १; ८. ६७, १७.
शश्वंता १. १६४, ३८.
शश्वान् २. ३८, ६.
शसंनं १. १६३, १२.
शसंने १०. ८९, १४.
शसा ५. ४१, १८.
शस्त १. १६२, १८; ४. ३७, ८.
शस्तं ३. ५३, ३; ५. ४७, ७; ८. ४५, २.
शस्तिः ४. ३, १५.
शस्तिऽभिः १. १८६, ३.
शस्ति ४. ३, ३.
शस्ते ४. २०, १०.
शस्मन् १. ११९, २.
शस्यते ५. ५५, ८.
शस्यते १. ५३, १; ८६, ४; ११०, १; १३८, १; ३. ६२, ७; ४. ४९, १; ५. १७, ४; ८. ७३, ११.
शस्यंते ७. ५६, २३.
शस्यमानः ७. ८, ३.
शस्यमानं ४. ४, १५; ५८, २; ८. २, १४; १०. ९१, ९.
शस्यमाना ३. ३९, १; २; ६. २४, ७.
शस्यमानाः ६. ६९, २.
शस्यमानानि १०. ६६, १२.
शस्यमानासः ६. ६९, ३.
शस्यमाने ६. २३, १; १०. ४५, १०.
शस्यमानेषु १०. ७२, १.
शस्यसे ६. ५, ६.
शाकः १०. ५५, ६.
शाकाः ६. २४, ४.
शाकिनः ५. ५२, १७; ८. ३३, ६.
शाकिनं ३. ५१, २; ८. ४६, १४.
शाकिने १. ५४, २; ६. ४५, २२.
शाकी १. ५१, ८.
शाके ५. १५, २.
शाकैः ४. १७, ११; ५. ३०, १०; ६. १९, ४.
शाक्तस्यऽइव ७. १०३, ५.
शाक्मना १०. ५५, ६.
शाखा १. ८, ८.
शाखाः ७. ४३, १.
शाखां १०. ९४, ३.
शाचिगो इति शाचिऽगो ८. १७, १२.
शाचिऽपूजन ८. १७, १२.
शाडः ६. ६३, ९.
शातपंता १०. १०६, ५.
शातऽवनेये १. ५९, ७.
शादेषु ९. १५, ६.
शाधि २. २८, ९.
शापं ७. १८, ५; १०. २८, ४.
शामुल्यं १०. ८५, २९.
शांबरं ६. ४७, २२.
शांबरे ३. ४७, ४.
शारदीः १. १३१, ४; १७४, २; ६. २०, १०.
शारि २. २८, ५; ३. ५३, १७; ६. ५४, ७.
शार्राः १. ११२, १६.
शार्यातस्य १. ५१, १२.
शार्याते ३. ५१, ७.
शाशदानः १. ३३, १३.
शाशदाना १. ११६, २; १२३, १०; १२४, ६.
शाशदानान् ७. ९८, ४.
शाशदानां ७. १०४, २४.
शाशदुः २. २०, ४.
शाशद्महे १०. १२०, ५.
शाशद्रे १. १४१, ९.
शाश्वसतः १०. ४८, ६.
शाश्वसत्ऽभिः १. ३०, १६.
शासः १. १३१, ४.
शासः १०. १५२, १.
शासत् १. ५१, ८; १३०, ८; ३. ३१, १.
शासतः ८. ३४, १.
शासता १. १३९, ४.
शासते १. १६५, ४; ९. ९९, ५.
शासन् १०. ३२, ४.
शासनीं १. ३१, ११.
शासने ३. ७, ५.
शासं १. ५४, ७; ६८, ५.
शासं ३. ४७, ५.
शासा ७. ४८, ३; १०. २०, २.
शासां २. २३, १२.
शासुः १. ६०, २; ७३, १; १०. १०६, २; ९.
शासुःऽइव १. ११६, १३.
शास्तनं १०. ५२, १.
शास्ते १. २४, ११; १६३, १३.
शास्वे ८. ३३, १६.
शास्महे १. ३०, १०.
शास्यः १. १८९, ७.
शास्सि १. ३१, १४.
शिंशपायां ३. ५३, १९.
शिंशुमारः १. ११६, १८.
शिक्वऽभिः १. १४१, ८; २. ३५, ४.
शिक्वसः ५. ५२, १६; ६. २, ९.
शिक्वसः ५. ५४, ४.
शिक्वसे १०. ९२, ९.
शिक्षं १. २७, ५; ६२, १२; २. ११,

२१; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; ७. २७, २; ३२, २६; ८. २, १५; ४१; ६६, १४; ९२, ९; ९. ८१, ३; ८७, ९; १०. ८१, ५.
शिक्ष ३. १९, ३; ३०, १५; ४. ३५, ३; ८. ४, १५; ९. १९, ६; १०. ४२, २; ६५, ५; १३३, ७.
शिक्षन् १०. २७, २२.
शिक्षतं १. १०९, ७; ८.
शिक्षतं १. ३४, ४; ८. २६, १२; ५९, ४; १०. ३९, ६.
शिक्षति ३. ५१, २; ८. ४९, १.
शिक्षति ६. २८, २.
शिक्षतु १. ८१, ६.
शिक्षते १. २८, ३.
शिक्षथः ८. ५९, १.
शिक्षन् १. १३२, ४; ६. २०, १०; २७, ५; ७; ७. १९, २; २०, ७; ८७, ४; ९. ७२, ८; १०. ४८, २; १०२, ७.
शिक्षन्ति १. १७३, १०.
शिक्ष १०. २७, १.
शिक्षमाणः ७. १०३, ५.
शिक्षमाणस्य ८. ४२, ३.
शिक्षसि ८. ५१, ६; ५२, ८.
शिक्षसि १. ८१, २.
शिक्षाः ३. ४३, ५.
शिक्षात् १. ६८, ३.
शिक्षाऽनरः १. ५३, २; ४. २०, ८.
शिक्षामि १०. ९५, १७.
शिक्षेम ३. ५२, ६.
शिक्षेयं ७. ३२, १९; ८. १४, २.
शिक्षो इति ८. ५२, ८.
शिक्षोः ३. १९, ३.
शिग्रवः ७. १८, १९.
शिङ्क्ते १. १६४, २९; ६. ७५, ३.
शिञ्जारैः ८. ५, २५; १०. ४०, ७.
शितः ८. २३, १३.
शिता १. ५४, ४.
शितिऽपादः १. ३५, ५.
शितिऽपृष्ठस्य ३. ७, १.
शितिऽपृष्ठा ८. १, २५.
शिथिरा ७. ४५, २.
शिथिराऽइव ५. ८५, ८.
शिथिरां ६. ५८, २.
शिथिरे ७. ७१, ५.
शिपिऽविष्ट ७. ९९, ७; १००.
शिपिऽविष्टः ७. १००, ६.
शिप्रऽवान् ६. १७, २.
शिप्राः ५. ५४, ११; ८. ७, २५.
शिप्राभ्यां १०. १०५, ५.
शिप्रिणीनां १. ३०, ११.
शिप्रिणीऽवान् १०. १०५, ५.
शिप्रिणे ६. ४४, १४; ८. ३२, २४.
शिप्रिन् १. २९, २; ८. २, २८.
शिप्रिन् ३. ३६, १०; ७. २५, ३; ८. १७, ४; ६१, ४.
शिप्री १. ८१, ४; ८. १, २७; ३३, ७; ९२, ४.
शिप्रे इति १. १०१, १०; ३. ३२, १; ५. ३६, २; ८. ७६, १०; १०. ९६, ९.
शिफायाः १. १०४, ३.
शिमीऽवतः १. ८४, १६.
शिमीऽवतां ८. २०, ३.
शिमीऽवति १०. ३८, १.
शिमीऽवतोः १. १५५, २.
शिमीवत्ऽभिः १. १४१, १३.
शिमीऽवंतः १०. ७८, ३.
शिमीऽवान् १. १००, १३; २. २५, ३; ५. ५६, ३; १०. ८, २; ८९, ५.
शिम्बलं ३. ५३, २२.
शिम्बाता १०. १०६, ५.
शिम्या १. १५१, १; ३.
शिम्युं ७. १८, ५.
शिम्यून् १. १००, १८.
शिरः १. ५२, १०; ८४, १४; ११७, २२; ११९, ९; १५८, ५; १६३, ६; २. २०, ६; ३. ५१, १२; ४. १८, ९; ५. ३०, ७; ८; ६. २०, ६; २६, ३; ५९, ६; ८. ६, ६; १४, १३; ७६, २; ९१, ५; ६; ९. ६८, ४; १०. २७, १३; ७९, २; ८६, ५; ७; १७१, २.
शिरिणायां २. १०, ३.
शिरिम्बिठस्य १०. १५५, १.
शिव ८. २६, २३.
शिवऽअभिमर्शनः १०. ६०, १२.
शिवः १. ३१, १; १८७, ३; २. २०, ३; ४. ११, ६; ५. १, ८; ५, ९; २४, १; ६. १५, ९; ४५, १७; ७. ९, ३; १९, १०; ३४, १५; ८. ४, १८; ३१, ३; ६३, ४; ९३, ३; १०. २५, ९; ९२, ९; १६५, २.
शिवऽतमः १०. ९, २.
शिवऽतमाः १. ५३, ११.
शिवऽतमां १०. ८५, ३७.
शिवऽतमाय ८. ९६, १०.
शिवं ३. ५८, ६; १०. १२४, २.
शिवस्य १०. ३, ४.
शिवा ४. १०, ८; १०. ३४, २; ८५, ४४.
शिवाः ७. ५०, ४; १०. १६, ४; १६९, ४.
शिवान् १०. ५३, ८.
शिवानि १. १०८, ५; ३. ५८, ६; ७. २२, ९.
शिवाभिः १. ७९, २; १८७, ३; ८. २०, २४; १०. ८, ६; ६७, ९.
शिवां ५. ४१, १७.
शिवायै १०. ९५, १३.
शिवासः ५. १२, ५; ७. १८, ७.
शिवे इति ६. ७५, १०.
शिवेन ७. ७३, ४.
शिवेभिः १. १४३, ८; ३. १, ९; १९; ६. ७१, ३; ८. ६०, ८.
शिशयं १०. ४२, ३.
शिशवः ७. ५६, १६.
शिशवे ४. १८, ८; १०. १३, ५.
शिशाः ६. १८, १३.
शिशाति ७. १८, ११; ८. १५, ७.
शिशातु १. १११, ५.
शिशाधि ६. १५, १९; ७. १०४, १९; ८. ४२, ३; १०. ८४, ४.
शिशानः ८. ६०, १३; ७६, ९; ९. ५, २; ६९, ३; ७०, ७; ८७, ७; १०. ८७, १; ३; ६; १०३, १; १५३, ४.
शिशामि १०. २८, ६; ४८, ४; ८७, २४; १२०, ५.

शिशींत **६.** ३, ५.
शिशीत **६.** १६, ४२; **८.** ४०, १०; ११; **१०.** ५३, १०.
शिशीतं **१.** १२२, ३.
शिशीतं **२.** ३९, ७; **७.** १०४, १.
शिशीतां **१०.** १२, ४.
शिशींते **१.** ३६, १६; ५५, १; **५.** २, ९; ९, ५; **७.** १०४, २०; **९.** १५, ४; **१०.** ५३, ९.
शिशीमसि **१.** १०२, १०.
शिशीहि **१.** ४२, ९; ८१, ७; **३.** २४, ५; **१०.** ४२, ३.
शिशीहि **३.** १६, ३; **७.** १६, ६; १८, २; १९, ८; **८.** ४, १६; २१, ८; **१०.** ८९, ९; १०५, ८.
शिशुः **१.** १४५, ३; **२.** ३५, १३; **५.** ४४, ३; **६.** २, ८; **७.** ९५, ३; **९.** ३८, ५; ७४, १; ९३, २; १०२, १; ११०, १०; **१०.** १, २; ६१, २०.
शिशुं **१.** ९६, ५; १४०, ३; १८६, ५; ७; **३.** १, ४; **४.** १५, ६; **५.** ९, ३; ४३, १४; **६.** ७, ४; १६, ४०; ४९, २; **७.** २, ५; **८.** ९९, ६; **९.** १, ९; ३३, ५; ८५, ११; ८६, ३१; ३६; ९६, १७; १०४, १; १०९, १२; **१०.** ४, ३; ५, ३; ७५, ४; १२३, १.
शिशुऽमतीः **१.** १४०, १०; **२.** ४३, २.
शिशुऽमंतः **८.** १००, ५.
शिशू इति **१०.** ८५, १८.
शिशूलाः **१०.** ७८, ६.
शिशोः **१०.** ११५, १.
शिश्नथः **८.** ६, १६; २४, २५; ७०, १०; **१०.** २२, १४.
शिश्नथत् **४.** ३०, १०.
शिश्नथत् **२.** २०, ५; **६.** ४, ३.
शिश्नथं **१०.** ४९, ३.
शिश्नथे **३.** ३१, १३.
शिश्नऽदेवाः **७.** २१, ५.
शिश्नऽदेवान् **१०.** ९९, ३.
शिश्ना **१.** १०५, ८; **१०.** २७, १९.
शिश्रथः **५.** ८५, ७.
शिश्रथः **१.** २४, १४; **२.** २८, ७; **४.** १२, ४; ३२, २२.
शिश्रथत् **१.** १२८, ६[२].
शिश्रथंतु **७.** ९३, ७.
शिश्रय **१०.** ४३, २.
शिश्राय **१०.** ४२, ६.
शिश्रियाणं **१.** ३२, २; **५.** ११, ६.
शिश्रिये **५.** ४४, १३; **१०.** ९१, २.
शिश्रीत **१.** १४९, २.
शिश्वः **१.** १२२, १५.
शिश्वा **१.** ६५, ५.
शिश्वे **२.** ३४, ८.
शिषः **६.** ७५, १६.
शिषंतः **१०.** ११५, ४.
शिषामहि **८.** २४, १.
शिष्ट **१.** २८, ९.
शीताः **१०.** ३४, ९.
शीतिंऽकावति **१०.** १६, १४.
शीतिके **१०.** १६, १४.
शीपालंऽइव **१०.** ६८, ५.
शीभं **१.** ३७, १४; **३.** ३३, १२; **१०.** ४४, २.
शीरं **३.** ९, ८; **८.** ४३, ३१; १०२, ११; **१०.** २१, १.
शीरऽशोचिषं **८.** ७१, १०; १४.
शीर्यते **१.** १६४, १३.
शीर्षणि **२.** १६, २; १७, २.
शीर्षण्य **१०.** १६३, १.
शीर्षण्या **१.** १६२, ८.
शीर्षतः **१०.** ८८, १६.
शीर्षन् **८.** ७, २५; ९६, ३.
शीर्षऽसु **५.** ५४, ११; ५७, ६.
शीर्षा **१.** ३३, ५; १३३, २; **६.** ६२, १०; **८.** ७४, १३; **१०.** ८, ९.
शीर्षाणि **७.** १८, १९; **१०.** ८७, १६.
शीर्षे इति **४.** ५८, ३.
शीर्ष्णः **१.** १६४, ७; **१०.** ९०, १४.
शीर्ष्णःऽशीर्ष्णः **७.** ६६, १५.
शीर्ष्णा **१.** ११६, १२; **१०.** २७, १३.
शीर्ष्णाऽशीर्ष्णा **१.** १३२, २.
शीर्ष्णेऽशीर्ष्णे **७.** १८, २४.
शीष्टेषु **८.** ५३, ४.
शुकेषु **१.** ५०, १२.
शुक्रं **७.** १, ८.
शुक्र **१.** १२७, २; **४.** ११, २; **५.** २१, ४; २३, ४; **६.** ४८, ७; **८.** ६०, ३.
शुक्रः **१.** ६९, १; ९५, १; **२.** ४१, २; **४.** १, ७; ४७, १; **६.** २, ६; ४, ३; १६, ३४; **७.** ६४, ५; **८.** २, ५; २५, १९; १०१, ९; **९.** ९७, ३२; १०९, ३; ५; ६; **१०.** १८७, ५.
शुक्रःऽइव **१.** ४३, ५.
शुक्रऽदुघस्य **६.** ३५, ५.
शुक्रऽपिशं **१०.** ११०, ६.
शुक्रऽपूतऽपाः **८.** ४६, २६.
शुक्रं **१.** ९५, ७; १४०, ११; १६०, ३; **२.** २, ७; **३.** ६, ३; ३२, २; ३४, ५; **४.** ३, १०; ६, ८; २७, ५; ४५, २; **५.** ४३, ३; ४; ४५, १०; **६.** ५८, १; ६६, १; **७.** ६०, ४; ६६, १६; ७७, २; **८.** १२, ३०; ६५, ११; **९.** १९, ५; ५४, १; ६६, २४; **१०.** ७, ३; २१, ७; ४३, ९.
शुक्रऽवर्चाः **१०.** १४०, २.
शुक्रऽवर्णं **१.** १४०, १.
शुक्रऽवर्णा **१.** १४३, ७.
शुक्रऽवासाः **१.** ११३, ७.
शुक्रऽशोचिः **७.** १५, १०.
शुक्रऽशोचिषं **२.** २, ३; **८.** २३, २०.
शुक्रऽशोचिषे **७.** १४, १; **८.** २३, २३; १०३, ८.
शुक्रऽशोचे **८.** ४४, ९.
शुक्रऽसद्मनां **६.** ४७, ५.
शुक्रस्य **५.** ६, ५.
शुक्रस्य **१.** ८४, ४; **२.** ९, ४; ४१, ३; **१०.** १०७, ६.
शुक्रा **१.** १२३, ९; १३५, २; **३.** १, ८; ८, ९; **७.** ३४, १; **९.** ४६, ४.
शुक्राः **१.** १३५, ३; ६; १३७, १; **३.** १, १४; **४.** ५१, ९; **८.** २, १०; ४४, १७; ९५, २; **९.** २१, ६; ३३, २; ६३, १४; ६४, २८; ६७, १८.
शुक्रान् **४.** २, २.

शुक्रां ९. ६२, २८; ९९, १.
शुक्रार्य ७. ४, १.
शुक्रासः १. १३४, ५; ६. ६, ४; ८. ४४, ४; ५२, १०; ९. ६३, २५; ६४, ४; ६५, २६; ६६, ५; ९७, २०.
शुक्रे २. ३४, २; ५. ४३, १४.
शुक्रेणं १. १२, १२; ४५, ४; ४८, १४; ४. ५२, ७; ६. ४८, ७; ८. ४४, १४; ५६, ५; ९. ८५, १२; १०. २१, ८; ४५, ७; १८७, ३.
शुक्रेभिः २. ३३, ९; ३५, ४; ३. १, ५; ९. १०२, ८.
शुक्रैः १. ९५, १०; ३. ४४, ५; ५. ७९, ८.
शुक्रौ १०. ८५, १०.
शुचतः ६. ३, ३.
शुचता २. ३४, १२.
शुचते ४. २३, १.
शुचत्ऽभिः १०. ६७, ७.
शुचत्ऽरथाः ४. ३७, ४.
शुचध्यै ४. २, १.
शुचंतः ४. २, १५; १७.
शुचंतं १०. ७९, ३.
शुचंति १. ११२, ७.
शुचमानः ४. २३, ८.
शुचयः १. ५, ५; ६४, २; ७२, ३; १३४, ४; ५; १८१, २; २. १, १३; २७, २; ९; ३५, ३; ४. ५१, २; ९; ६. ६, ३; ४; ६६, ४; ११; ७. २, २; ४९, २; ३; ५६, १२; ५७, ५; ९०, १; ८. ३, ३; ४४, १७; ५२, १०; १०. १२४, ७.
शुचयत्ऽभिः ४. ५६, १; २; १०. ४, ६.
शुचयंतः १. १४७, १.
शुचयंतं १०. ४६, ८.
शुचये ३. १, १०; ७. ४१, ६.
शुचस्य १०. २६, ६.
शुचायाः १०. २६, ६.
शुचाऽशुचा ३. ४, १.
शुचि १. ७१, ८; १२१, ५; १४०, ११; ४. १, ६; १९; २, १६; १०, ६; ६. १०, २; ५१, १; ९. ६७, १२.
शुचिः १. ६६, १; ९१, ३; १२७, ७; १४१, ४; ५; १४२, ३; ९; १६०, १; १८०, ३; २. १, १; १४; ५, ४; ७, ४; २७, १३; ३. ५, ७; ४. १, ७; ५. १, ३; ७, ८; ११, १; ३; ६. ८, १; १५, १; ७. ३, ९; १०, १; १५, १०; ९५, २; ९७, ७; १०४, १६; ८. २, ९; १३, १९; २९, ५; ४४, २१[३]; ९. ९, ३; २४, ६; ७; ७०, ८; ७२, ४; ७५, ४; ८५, १२; ८६, १३; १०. १७, १०; २९, १; ४३, ९.
शुचिऽक्रंदं ७. ९७, ५.
शुचिऽजन्मनः १. १४१, ७; ६. ३९, ३.
शुचिऽजन्मानः ७. ५६, १२.
शुचिऽजिव्हः २. ९, १.
शुचिऽदन् ५. ७, ७; ७. ४, २.
शुचिना २. ५, ४; ३५, ८.
शुचिऽपा ७. ९१, ४.
शुचिऽपाः ७. ९०, २; ९२, १.
शुचिऽपे १०. १००, २.
शुचिऽपेशसं १. १४४, १.
शुचिऽप्रतीकं १. १४३, ६.
शुचिऽबंधुः ९. ९७, ७.
शुचिऽभिः ५. १, ३; ६. ६२, २.
शुचिऽभ्यः ७. ५६, १२.
शुचिऽभ्राजाः १. ७९, १.
शुचिं १. ७२, ३; १४०, १; २. ३५, ३; ३. २, १४; १५; ६२, ५; ५. ४, ३; ६. १५, ७; ७. ४७, १; ५६, १२; ९०, २; ९१, ४; ९३, १; ८. १०१, १०; १०२, ४; ९. १०५, ४.
शुचिऽवर्णे ५. २, ३.
शुचिऽव्रत ८. ४३, १६.
शुचिऽव्रत १०. ११८, १.
शुचिव्रतऽतमः ८. ४४, २१.
शुचिऽव्रता १. १८२, १; ६. १६, २४.
शुचिऽव्रता १. १५, ११; ३. ६२, १७.
शुचिव्रते इति शुचिऽव्रते ६. ७०, २.
शुचिष्मः ६. ६, ४.
शुचिऽसत् ४. ४०, ५.
शुचीं ७. ५६, १२.
शुची इति ४. ५६, ५; १०. ८५, १२.
शुचीनां १. ३०, २; ७. ५६, १२; ९. ५२, ५.
शुचीनि २. ३३, १३.
शुचे १. ३१, १७; ६. ६, ३; ४८, ३; ७. ८९, ३; ८. ४३, १३.
शुतुद्रि १०. ७५, ५.
शुतुद्री ३. ३३, १.
शुद्धः ८. ९५, ७; ८[४]; ९[४]; ९. ७८, १.
शुद्धं १. १६४, ४०; ८. ९५, ७.
शुद्धाः ६. २८, ७; १०. १८, २.
शुद्धाभिः ८. ९५, ८.
शुद्धेन ८. ९५, ७
शुद्धैः ८. ९५, ७.
शुनः १. १८२, ४; ४. १८, १३; ८. ५५, ३.
शुनःऽशेपः १. २४, १२; १३.
शुनःऽशेपं ५. २, ७.
शुनऽपृष्ठः ७. ७०, १.
शुनं १. ११७, १८; ३. ३०, २२; ४. ३, ११; ५७, ४[४]; ८[४]; ६. १६, ४; १०. १०२, ८; १२६, ७; १६०, ५.
शुनऽहोत्रेषु २. १८, ६; ४१, १४; १७.
शुनाऽइषितं ८. ४६, २८.
शुनासीरा ४. ५७, ८.
शुनासीरौ ४. ५७, ५.
शुंधत १०. १७, १४.
शुंधति १०. ८५, ३५.
शुंधयंतु १०. १७, १०.
शुंध्यवः ५. ५२, ९.
शुंध्युः ७. ९७, ७; ८. २४, २४.
शुंध्युं १०. ४३, १.
शुंध्युवः १. ५०, ९; १२४, ४.
शुंध्युवं ७. ८८, १; १०. ३९, ७.
शुंध्यूः १०. १३८, ५.
शुसौ १. ५१, ५.
शुभंः १. ३, १; ५. ५४, ११; ९. ९४, १.
शुभः ८. ५, ५; २२, १४; २६, ६; १०. ४०, १४; ९३, ६.
शुभः १. ३४, ६; ४७, ५; १२०, ६; ५. ७५, ८; ८. ५, ११; २२, ४; ६; ५९, ३; ५; ८७, ५; १०. ४०, ४; १२; १३; ८५, १५; १३१, ४.

शुभं १. २३, ११; ४. ५१, ६; ५. ५५, १; ५७, २; ६. ६२, ४; ७. ८२, ५.
शुभंऽयर्वः १०. ७८, ७.
शुभंऽयावा ५. ६१, १३.
शुभंऽयावानः १. ८९, ७.
शुभंऽये ४. ३, ६.
शुभयंत्ऽभिः ५. ६०, ८.
शुभयंत ७. ५६, १६.
शुभयंते १. ८५, ३.
शुभा १. १६५, १; ७. ५६, ६.
शुभाना ७. ७२, १.
शुभानैः १. १६५, ३.
शुभायते ९. २८, ३.
शुभे १. ६४, ४; ८७, ३; ८८, २; ११७, ५; ११९, ३; १२७, ६; १६७, ६; ३. २६, ४; ५. ५२, ८; ५७, ३; ६३, ५; ६. ६३, ६; ७. ५७, ३; ८७, ५; ८८, ३; ८. २६, १३; १०. १०५, ३.
शुभ्र ५. ५, ४.
शुभ्रः २. ११, ४; ७. ५६, ८; ९. १४, ५; ९६, २०.
शुभ्रऽखादयः ८. २०, ४.
शुभ्रं २. ११, ४[२]; ३. २६, २; ९. ६२, ५; १०७, २४.
शुभ्रऽयामा ३. ५८, १.
शुभ्रऽयावाना ८. २६, १९.
शुभ्रऽवंता ९. १५, ३.
शुभ्रशाःऽतमः ९. ६६, २६.
शुभ्रा १०. १४३, ३.
शुभ्रा ५. ८०, ५; ७. ७५, ६.
शुभ्रा ७. ६८, १.
शुभ्राः १. १९, ५; ८५, ३; १६७, ४; २. ११, ३; ४. ५१, ६; ५. ४१, १२; ४२, १२; ७. ३९, ३; ५६, १६; ८. ७, २५; २८; ९. ६३, २६.
शुभ्राः ८. ७, २; १४.
शुभ्राभ्यां १. ३५, ३.
शुभ्रासः २. ३६, २.
शुभ्रिषु १. २९, १–७; ५. ३४, ८.
शुभ्रे १. ५७, ३; ७. ९५, ६; ९६, २.
शुभ्रे इति ३. ३३, १.
शुभ्रे इति ३. ३३, २.
शुभ्रेभिः ९. १५, ५; ६६, २६.
शुभ्वां ४. ३८, ६.
शुंभ ८. ७०, २.
शुंभत १. २१, २; १०. ९५, ९.
शुंभति १. २२, ८.
शुंभंते ९. ३८, ३.
शुंभते १. १४०, ६.
शुंभंतः १. १३०, ६.
शुंभंति ५. १०, ४; ९. ४०, १; ९६, १७; १०. २१, २.
शुंभंति ५. २२, ४; ३९, ५; ९. ४३, २.
शुंभंत १. ८५, १.
शुंभमानः ९. ३६, ४.
शुंभमाना १. ९२, १०; १०. १०७, १०.
शुंभमाना ६. ६४, २.
शुंभमानाः १. ३३, ८; १६५, ५; ३. ५, ८; ७. ५६, ११; ५९, ७; १०. ११०, ५.
शुंभमानाः ९. ६४, ५.
शुंभमाने इति २. ३९, २.
शुंभसे ९. २, ७.
शुंभानः ८. ४४, १२.
शुंभामि ८. ६, ११; ४४, २६.
शुरुधः १. ७२, ७; १६९, ८; ३. ३८, ५; ४. २३, ८; ६. ३, ३; ४९, ८; ७. २३, २; ६२, ३; ९. ७०, ५; १०. १२२, १.
शुल्कायं ७. ८२, ६; ८. १, ५.
शुशुकनं १. १३२, ३.
शुशुकनिः ८. २३, ५.
शुशुक्वांसः ५. ८७, ६.
शुशुक्वान् १. ६९, १; १६९, ३; १८९, ४.
शुशुग्धि १. ९७, १.
शुशुचान ४. १, ३.
शुशुचानः १. १४९, ४; १०. ९८, ८.
शुशुचानं ४. १, १९.
शुशुचानस्यं ४. २२, ८.
शुशुचानाः २. ३४, १.
शुशुचानासः १. १२३, ६.
शुशुचीत २. २, १०; १०. ४३, ९.
शुशुलूकंऽयातुं ७. १०४, २२.
शुशोचं १. १३३, ६; १०. १३८, २.
शुशोच ७. ४, ३; ८, ४.
शुश्रवं १०. ३८, ५.
शुश्रव १. १०९, ५.
शुश्रवत् १. ८४, ८.
शुश्राव १. १०५, १७; ५. ५३, २.
शुश्रुयाः ८. ४५, १८.
शुश्रुयातं ५. ७४, १०; ८. ७३, ५.
शुश्रुऽवांसा ७. ७०, ५.
शुश्रुऽवान् १०. ७१, ५.
शुश्रुवे ८. ६६, ९.
शुश्रूंपमाणः ४. ३८, ७; ७. १९, २.
शुषंतं १. ६१, १०.
शुषे ८. ९३, १६.
शुष्कं २. १३, ६; ४. ४, ४; ६. १८, १०; ७. १०३, २.
शुष्कात् १. ६८, २.
शुष्कासु १०. ९२, १.
शुष्णः ६. २०, ५.
शुष्णं १. ११, ७; ३३, १२; ५६, ३; ६३, ३; १०१, २; १०३, ८; १२१, ९; २. १४, ५; १९, ६; ३. ३१, ८; ४. १६, १२; ५. २९, ९; ३२, ५; ६. १८, ८; २६, ३; ३१, ३; ७. १९, २; ८. ५१, ८; १०. २२, ७; १४; ९९, ९; १११, ५.
शुष्णंस्य १. ५१, ११; ५४, ५; १२१, १०; ४. ३०, १३; ५. ३१, ७; ६. २०, ४; ८. १, २८; ४०, १०; ११; ९६, १७; १०. २२, ११; ४९, ३; ६१, १३.
शुष्णऽहत्येषु १. ५१, ६.
शुष्णाय १. १७५, ४.
शुष्णे ८. ६, १४.
शुष्मः १. १००, २; १६५, ४; ४. २१, ७; २३, १०; ६. १९, ९; ६८, ७; ७. ३, ६; २७, २; ५६, ८; ६१, ४; ९. ७९, ५; १०. १८०, १.
शुष्मं १. ६४, १४; १६५, १; २.

११, ४; १७, ३; ३. ३२, ३; ३७, १०; ४. १७, १२; २४, ७; ५. १६, ३; ३२, ९; ६. १९, ८; ४४, ५; ७२, ५; ७. २४, ४; ३३, ४; ८. ६, ११; ७, २४; १५, ७; २०, ३; ९३, १२; ९६, ८; ९९, ६; ९. १९, ७; २९, ६; ३०, ३; ५२, ४; ६३, २९; ६७, ३; ७६, २; १०६, ४; १०. ७५, ३; ११३, १.

शुष्माः १. ५२, ४; २. १७, १; ४. १०, ४; १०. ९७, ८; १४२, ६.

शुष्मात् २. १२, १; १३; ६. २७, ४; ७. ३४, ७; १०. १४७, १.

शुष्माय ८. ७, ५.

शुष्मासः ५. ३८, ३; ९. ५०, १; ५३, १; १०. ३, ६.

शुष्मिणः १. १४५, १; ३. १६, ३; ५. १०, ४; ९. १४, ३; ३०, १; ४१, ३; १०. ४३, ३.

शुष्मिणं ७. २३, ५; ८. १३, ३; १०२, १२.

शुष्मिणा ४. ४७, ३.

शुष्मिणे १. ३०, ३; ३७, ४.

शुष्मिन् १. १७३, १२; ६. २५, १; ७. ३०, १; ८. ९८, १२.

शुष्मिन्ऽतमः १. १२७, ९; १३३, ६; १७५, ५.

शुष्मिन्ऽतमं २. ११, १३; ३. ३७, ८.

शुष्मिऽभिः १. १३३, ६.

शुष्मी ४. २२, १; ४; ५. ४०, ४; ७. ४०, ३; ५६, २४; ९. १८, ७; २७, ६; २८, ६; ७१, १; ८८, ७.

शुष्मेण ४. ५०, ७; ९. ७०, ५.

शुष्मेभिः ५. १०, ४; ६. ६१, २.

शुष्मैः १. ६३, १; ४. २२, ३; ६. ३, ८; ३२, ४; ६०, ३; ७. ७, २.

शुष्यतु ७. १०४, ११.

शूकृतस्य १. १६२, १७.

शूघनासः ४. ५८, ७.

शूद्रः १०. ९०, १२.

शूने २. २७, १७; २८, ११; २९, ७; ३. ३३, १३; ८. ४५, ३६.

शूनैः १. १०५, ३; ७. १, ११; १०. ३७, ६.

शूरं ५. ३८, ५.

शूर १. ११, ६; २९, ४; ३२, १२; ६३, ४; ८; ८१, ८; १२९, ३; ५; १३१, ७; १३२, ६; १३३, ६; १७३, ७; १७४, ९; २. ११, २; ३; ५; ११; १७; १८; १८, ७; १९, ८; ३०, १०; ३. ३०, ११; ४१, ३; ४७, २; ५१, ७; १२; ५२, ७; ५३, २१; ४. ३, १५; १६, २; ७; १७; २२, ५; ३२, २१; ५. ३३, ७; ३५, २; ३६, २; ६. १५, ११; १९, ६; १३; २४, ३; २६, ५; ३३, ३; ४; ४४, १७; ४७, ६; ७. १९, ११; २१, ३; २२, ७; २३, ५; २५, ४; ५; ३०, १; ४; ३२, ११; २२; २७; ३६, ४; ८. १, १४; २१, ८; २४, २; ८; ३२, ५; ३४, १४; ४५, ३४; ४६, ११; ४९, ३; ५०, ९; ६१, ५; ६२, ११; ६३, ११; ६६, ५; ७०, ९; ७८, १; ४; ८१, ३; ९७, १५; ९८, ८; १०. २२, ९–१२; ४७, १; ५०, २; ७३, ४; ९८, १०; ११२, १; १३१, १; १४८, २; ४; ५.

शूरः १. ७०, ६; १०३, ६; १०४, ४; १२२, १०; १३२, ५; १५८, ३; १७३, ५; १७५, ३; १७८, ३; २. १७, २; ४. २१, १; २७, ५; ३६, ६; ५. ६३, ५; ६. २५, ४; ५; ३५, ५; ६४, ३; ७. १८, ११; १९, १०; २०, ३; २७, १; ८४, ४; ८. २, ३६; ३१, १५; ४५, ३; ६१, १८; ९२, २८; ९. १, १०; ३, ४; १५, १; १६, ६; ६२, १९; ७०, १०; ७६, २; ८७, ७; ८९, ३; ९४, ३; ९६, १; १०. ४२, ४; ५५, ६; ८; १०५, ४; ६.

शूरःऽइव १०. ६९, ५.

शूरऽग्रामः ९. ९०, ३.

शूरणासः १. १६३, १०.

शूरऽतरः ९. ६६, १७.

शूरःऽपत्नि १०. ८६, ८.

शूरऽपत्नीः १. १७४, ३.

शूरे १. ११२, १८; ४. ३८, २; ३; ६. २५, ४; ४७, ११; ९. ८१, १; १०. ४२, २; ११४, ९.

शूरऽसाता १. ३१, ६; १५७, २; ७. ९३, ५; १०. ६३, १४.

शूरऽसातौ १. १००, ७; ३. ५४, ४; ६. १९, १२; २३, २; २६, १; ३३, २; ८. १६, ४; १०. ६७, ९.

शूरस्य ८. २, ९.

शूरस्यऽइव १. १४१, ८; ३. ५५, ८; ६. ६, ५.

शूरा ४. ४१, ७.

शूराः ७. १, १०; ३०, २; ३४, ३; ५६, २२; १०. ७८, ४.

शूराः १. ६४, ९.

शूराःऽइव १. ८५, ८; ५. ५९, ५.

शूराणां ६. ६८, २.

शूराय १. १५५, १; ८. २, २५.

शूरासः ६. ४६, १२; १०. १५४, २.

शूरेभिः १. ८, ४; १०१, ६.

शूरेभ्यः ९. ६६, १७.

शूरैः १. १२९, २; २. ३०, १०; ८. १९, १०; १०. २२, ९.

शूर्ताः १. १७४, ६.

शूले १. १६२, ११.

शूशवाम १. १६६, १४.

शूशुजानः १०. ३४, ६.

शूशुजानान् १०. २७, २.

शूशुयाम ८. २१, १२.

शूशुवत १. ५४, ७; २. २५, १; ८. ३१, ३.

शूशुऽवांसः १. १६७, ९.

शूशुऽवांसं १. ६४, १५; ४. १६, १३; ६. १९, २; ७; ८; १०. ४७, ४.

शूशुऽवांसा ७. ९३, २.

शूशुवानः ४. २७, २; ७. २०, २; १०. २८, ९.

शूशुवानस्य १०. १११, ६.

शूशुवुः ७. ७४, ६.

शूशुवे ७. ३२, ६.

शूषः ९. ७१, २.

शूषणि १०. ९३, १.

शूषं १. ९, १०; ६२, १; १५४, ३; ३. ७, ६; ५४, १; ६. १०, २;

७. २५, ५; १०. ३१, ३; ५४, ६, ९६, २; १२०, ८; १३३, १.
शूषस्यं १. १३१, २; ८. ७४, १.
शूषे इति ९. ९७, ५४.
शूषेभिः १०. ६, ४.
शूषैः ३. ४९, २; ५. ४१, ७; १०; ६. १२, ४; ६८, ३; १०. ६, ३.
शूर्प्यः ७. ६६, १.
शूर्प्यं १. ५४, ३; ५. ८६, ६.
शृंगं ५. ५९, ३; ८. ८६, ५.
शृंगऽवृषः ८. १७, १३.
शृंगा १. १४०, ६; ४. ५८, ३.
शृंगाऽइव २. ३९, ३.
शृंगाणि १. १६३, ११; ९. १५, ४.
शृंगाणिऽइव ३. ८, १०.
शृंगिणः १. ३२, १५.
शृंगिणं १. ३३, १२.
शृंगिणा ३. ८, १०.
शृंगे इति ५. २, ९; ८. ६०, १३; ९. ५, २; ७०, ७; ८७, ७.
शृणंतु १०. ८७, १५.
शृणवः ६. ४०, ४; ७. २९, २; ३.
शृणवत् ५. १४, ५; ३०, ३; ७. २६, १; ८. ३३, ९; १३; ६१, १; १०.
शृणवत् १. १४१, १२; १४५, ३; ३. ४३, ४; ४. ५८, २; ८. ४३, २२; १०. २६, ९; ६६, ११.
शृणवन् ९. ४९, ४.
शृणवन् ३. ५४, १०; १३; १०. ६५, १३.
शृणवाम ३. ३३, १०.
शृणाति १०. ८९, ६.
शृणानाः १०. २८, ११.
शृणासि १०. ८९, ८.
शृणीतं ७. १०४, १.
शृणीहि १०. ८७, २५.
शृणीहि ३. ३०, १७; १०. ८७, ५; १०[२]; १४[२].
शृणु ८. १७, २; ३६, ७; ४५, ६.
शृणुत १. ८६, २; २. ४१, १३; ६. ५२, १३; १०. ३०, ८.
शृणुतं १. ९३, १; ६. ६०, १५; ७. ८२, ८; ९४, २; ८. ७३, १०; ८५, ४; १०. १२, ४; ३९, ६.
शृणुतं १. ४७, २; ८९, ४; ११८, ३; १८१, ७; ३. ६२, २; ६. ६९, ४; ७. ६७, १०; ८३, ४; ८. ३५, १९; ३८, ८; ८५, २; १०. ६७, ११.
शृणुते १०. ११३, ९.
शृणुधि ८. १३, ७; ८४, ३.
शृणुधि ४. ९, ७; ८. ३, १८; ५२, ८.
शृणुयाम १. ८९, ८.
शृणुष्व १. १३१, ७.
शृणुहि १. ८२, १; ९. ८२, ४; १०. ७५, ५.
शृणुहि १. १०४, ९; १३९, ७; ४. २२, १०; ७. २८, १.
शृणोत ३. ३३, ९.
शृणोतन १०. ३६, १०; ६२, ४.
शृणोति १. ३७, १३; १०. ७१, ६; १२५, ४.
शृणोति ४. २३, ३; ८. ७८, ५; १०. ७१, ४; ६.
शृणोतु १. ११४, ११; २. २७, १; ३२, ४; ३. ५४, १[२]; १९; ५. ४१, १२; ७. ४४, ५; ४६, १; ८. ५४, ४; ९३, १८; १०. ९१, १३.
शृणोतु १. २७, १२; ३. ५४, २०; ५. ४२, १; ४३, ११; ४६, ८; ६. ५०, १४; ५५, ५; ७. ३५, ६; ३८, ५; १०. ६४, ४; १०; ९२, १२.
शृणोमि ५. ३२, १२; ८. २, ११.
शृणोमि २. ३३, ४; ५. ३२, ११; १०. ४२, ३.
शृण्वतः २. २९, १; १०. ६३, ११.
शृण्वतां १०. ६४, १.
शृण्वते १. ७४, १; १०. १८, १.
शृण्वन् २. २३, १; ४. २३, ३; ६. १६, ६; १०. ७१, ४; ८५, ४.
शृण्वंतं १. ५४, २; ३. ३०, २२; ६. ५४, ८; ८. ४३, २३; १०. १२२, ४.
शृण्वंता १. ३४, १२.
शृण्वंति ७. ३४, १.
शृण्वंति २. २४, १३.
शृण्वंतु १. ४४, १४; ३. ५४, २०; ५. ४१, १२; ६. ५२, ९; ७. ३५, १४; ४४, ५; ८. ५४, ३; १०. १३, १.
शृण्वंतु ३. २०, १; ५. ५२, १४; १०. ३७, ६; ६४, ६.
शृण्विरे १. १५, ८; ४. ८, ६; ५. ८७, ३.
शृण्विरे ८. ४५, ४; ५४, ६; ७७, १; १०. १६८, ४.
शृण्विषे ८. ६, १४; ३३, १०; ७८, ३.
शृण्विषे ४. ४२, ७; ७. ८, ५.
शृण्वे १. ७४, ७; ३. ५५, २०; ४. १७, ९; ५. ७३, ७; ६. ४७, १६; ८. २, ३४; ४५, ३२; ९. ४१, ३; १०. ९४, ६.
शृण्वे १. ३७, ३; १६९, ७; ३. ३०, १६; ४. १७, १०; २०, ९; ४१, २; ७. ८, ४; २६, ४; ९. ९७, १३; १०. ११, ७.
शृतऽपाकं १. १६२, १०.
शृतऽपान् १०. २७, ६.
शृतऽपां ७. १८, १६.
शृतं ९. ११४, ४; १०. १६, १; २.
शृतासः ९. ८३, १.
शृध्यां २. १२, १०.
शेक ५. ६१, २.
शेकुः १०. ४४, ६.
शेकुः ९. ७३, ३; १०. ८८, १७.
शेपः ९. ११२, ४.
शेपं १०. ८५, ३७.
शेपा १०. १०५, २.
शेपे १. २३, २२.
शेवं ९. ८२, ४.
शेवः १. ६९, २; ७३, २.
शेवधिऽपाः ८. ५१, ९.
शेवऽधिं २. १३, ९.
शेवं १. ५८, ६; ३. ७, ५; ५. ६४, २; १०. ११३, ५; १२२, १; १२४, ३.
शेवस्य १०. २०, ७.
शेवारे ८. १, २२.
शेऽवृधः ५. ८७, ४; १०. ४६, ३.
शेऽवृधं १. ५४, ११.
शेऽवृधं १०. ६१, २०.
शेऽवृधासः ३. १६, २.

शे॑र्यः १. १५६, १.
शे॑र्पः १. ९३, ४; ५. १२, ६; ६. २७, ४; ५; ७. ४, ७; १०. १३, ५.
शे॑र्पन् १. १७४, ४.
शे॑र्पसा ५. ७०, ४; ७. १, १२.
शे॑र्पे ८. ६०, १५.
शे॒पे॒ १०. १८, ८.
शो॑कः २. ३८, ५.
शो॑कं १०. ३१, ९.
शो॑काः १. १२५, ७; ४. ६, ५.
शो॑कैः १०. १०३, १२.
शो॑च ६. १६, ४५; ७. २, १; ८. ६०, ६.
शो॒च॒ ३. १३, ६; ६. १६, ११; १०. ६९, ३.
शो॒च॒ः १०. १६, १.
शो॑चतः ७. १५, ५.
शो॒च॒तु ६. ५२, २.
शो॑चत्ऽभिः ५. ७९, ८.
शो॑चन् ७. ५०, २; १०. ९२, १.
शो॑चंत ८. ६, ८.
शो॑चंतः ९. ७३, ५; ८३, २.
शो॑चंति ५. १७, ३.
शो॒च॒य ६. २२, ८.
शो॑चस्व १. ३६, ९.
शो॒च॒स्व॒ ४. २, २०.
शो॒चिः १. ३९, १; १४३, २; १४८, ४; ३. १, ५; ४. ६, ६; ७, १०; ५. २८, १; ६. ६४, २; ७. ३, ५; १६, ३; ८. ६, ७; १०. १६, ४.
शो॒चिःऽकेशः ३. १४, १; १७, १; २७, ४; ५. ४१, १०.
शो॒चिःऽकेशं १. ४५, ६; ५०, ८; १२७, २; ५. ८, २.
शो॒चिषः ४. ५, १०.
शो॒चि॒षः ५. ६, ५.
शो॒चिषा १. १२, १२; ४५, ४; ४८, १४; १२७, १; ४; १७५, ३; ३. २, ४; १४, ४; १८, ४; ४. ५, ४; ५२, ७; ६. ३, ६; ४, ६; १०, ४; १२, १; १६, २८; २२, ८; ४८, ३; ७; ६८, ९; ७. ५, ४; १३, २; ८. ४४, १४; ५६, ५; ६०, १६; १०२, १६; ९. ८५, १२; १०. २१, ८; ४५, ७; ८७, २३; ११५, ३; ११८, ७; १८७, ३.
शो॒चि॑षे ५. ५, १.
शो॒चि॒ष्ठ ५. २४, ४; ८. ६०, ६.
शो॒चिष्मा॑न् २. ४, ७.
शो॒ची॑षि ३. ४, ४; ७. ४३, २.
शो॑णः ९. ९७, १३; १०. २०, ९.
शो॑णा १. ६, २; ३. ३५, ३.
शो॑णाः १. १२६, ४; ५. ३३, ८.
शो॒भ॒ते॒ ९. २५, ३; ६९, ३.
शो॑भमानं ५. २, ४.
शो॒भसे॑ १. ८४, १०; १०. ७७, १.
शो॒भ॒से॒ ५. ४४, ५.
शो॑भिष्ठं ८. ३, २१.
शो॑भिष्ठाः ७. ५६, ६.
शो॑भे १. १२०, ५.
शो॒भ॒ते॒ इति॑ ४. ३२, २३.
शो॑शुचत् १. ९७, १[२]; २–८; ६. ४८, ३.
शो॑शुचतः १०. ८७, २०.
शो॑शुचता १. १२३, ७.
शो॑शुचत्याः १०. ८९, १२.
शो॑शुचन् ६. ६६, २.
शो॒शु॒चं॒त॒ ७. १, ४.
शो॑शुचानः ३. १५, १; ४. १, ४; ४, २; ७. ५, ३; ४; १०, १; १३, २; १०. ८७, ७; १४.
शो॑शुचानं १०. ८७, ९.
शौ॒च॒त्ऽर॒थे ५. ७९, २.
शौ॒र॒ऽदे॒व्यः ८. ७०, १५.
श्र॒म्न॒न् १. १०४, २.
श्चो॑तंति १. ८७, २; ३. १, ८; २१, ५.
श्चो॒तं॒ति॒ ३. २१, २; ४; ४. ५०, ३; ७. १०१, ४; ८. २, ८.
श्न॑थत् ६. ६०, १.
श्न॑थनः २. २१, ४.
श्न॒थ॒यः १०. ९५, ५.
श्न॒थय॑न् १. ५१, ९.
श्न॒थ॒यं॒त॒ ८. ९९, ६.
श्न॒थयं॑तं ७. ८२, ६.
श्न॒थि॒तं १. ११६, २४.
श्नथि॑ता १. ५७, २; १०. ४९, ३.
श्न॒थि॒ता १०. ९५, ४.
श्न॒थि॒ष्ट॒न ९. १०१, १.
श्न॒थि॒ष्टं ७. ९९, ५.
श्न॒थि॒हि॒ १. ६३, ५; ७. २५, २.
श्म॒शा १०. १०५, १.
श्मश्रु॑ १०. २३, १; २६, ७; १४२, ४.
श्मश्रु॑षु २. ११, १७; ८. ३३, ६.
श्मश्रू॑णि १०. २३, ४.
श्म॒सि॒ २. ३१, ६.
श्य॒त् १. १३०, ४[२].
श्या॒म॒ १०. १२८, ३.
श्या॒व॒ऽअ॒श्व॒ ५. ५२, १.
श्या॒व॒ऽअ॑श्वः ५. ८१, ८.
श्या॒व॒ऽअ॑श्वस्य ८. ३६, ७; ३७, ७; ३८, ८.
श्या॒वऽअ॑श्व्यस्य ८. ३५, १९.
श्या॒वः ८. १९, ३७; १०. ३१, ११.
श्याव॑कं ८. ३, १२.
श्याव॑के ८. ४, २.
श्याव॑ १. ११७, २४; १०. ६५, १२.
श्या॒वं १०. ६८, ११.
श्या॒वा १. १००, १६; २. १०, २.
श्या॒वाः १. ३५, ५; १२६, ३; ६. ४८, ६; ८. ४६, २३.
श्यावा॑य १. ११७, ८.
श्या॒वाय॑ ५. ६१, ९.
श्या॒वाश्व॑ऽस्तुताय ५. ६१, ५.
श्या॒वासु॑ ६. ४८, ६.
श्यावीं॑ ३. ५५, ११.
श्यावीः॑ ८. ५५, ५.
श्यावी॑नां ८. ४६, २२.
श्यावी॑ १. ७१, १.
श्या॒व्या॑भ्यः ६. १५, १७.
श्ये॒तः १. ७१, ४.
श्ये॒तं ७. ४, ३.
श्येता॑सः ५. ३३, ८.
श्ये॒नऽआ॑भृतः १. ८०, २.
श्ये॒नऽआ॑भृतं ८. ९५, ३.
श्ये॒नः १. ३२, १४; ३३, २; ९३, ६; २. ४२, २; ३. ४३, ७; ४. १८, १३; २६, ४–७; २७, १; ३; ४; ५. ४४, ११; ४५, ९; ६. २०, ६; ७. ६३, ५; ८. ८२, ९; ९. ३८, ४; ५७, ३; ६१, २१; ६२, ४;

६५, १९; ६७, १४; १५; ६८, ६; ७१, ६; ७७, २; ८२, १; ८६, ३५; ९६, ६; १९; **१०.** ११, ४; ९९, ८; १४४, ५.
श्येनऽजूतः **९.** ८९, २.
श्येनऽपत्वा **१.** ११८, १.
श्येनऽभृत **९.** ८७, ६.
श्येनं **४.** ३८, २; ५; **८.** ३४, ९.
श्येनस्य **१.** ११८, ११; १६३, १; **५.** ७८, ४; **१०.** १४४, ४.
श्येनस्यऽइव **४.** ४०, ३.
श्येनाऽइव **५.** ७४, ९; **८.** ७३, ४.
श्येनाः **७.** ५६, ३.
श्येनाःऽइव **४.** ३५, ८.
श्येनान्ऽइव **१.** १६५, २; **६.** ४६, १३.
श्येनाय **७.** १५, ४; **१०.** १४४, ३.
श्येनासः **१.** ११८, ४; **४.** ६, १०; **८.** २०, १०; **१०.** ७७, ५; ९२, ६; १२७, ५.
श्येनी **१.** १४०, ९.
श्येनेभिः **८.** ५, ७.
श्येनेभ्यः **४.** २६, ४.
श्येनौऽइव **८.** ३५, ९.
श्रत् **१.** ५५, ५; १०३, ५; १०४, ७; **२.** १२, ५; **८.** ७५, २; **१०.** ३९, ५; १४७, १; १५१, ५.
श्रत्ऽदधानः **१.** १०३, ३.
श्रथय **१.** २४, १५; **२.** २८, ५.
श्रथयन् **९.** ६८, २.
श्रथयंत **५.** ५४, १०; ८५, ४.
श्रथयंते **५.** ५९, १.
श्रथयति **१०.** ७७, ४.
श्रथीते **९.** ६९, ३.
श्रद्धया **८.** १, ३१; **९.** ११३, २; **१०.** १५१, १[२]; ४.
श्रद्धा **७.** ३२, १४.
श्रद्धाभिः **२.** ६६, ६.
श्रद्धां **१.** १०८, ६; **९.** ११३, ४; **१०.** १५१, १; ३; ४[२]; ५[२].
श्रद्धाऽमनस्या **१०.** ११३, ९.
श्रद्धाऽमनाः **२.** २६, ३.
श्रद्धितं **१.** १०४, ६.
श्रद्धिऽवं **१०.** १२५, ४.
श्रद्धे **१०.** १५१, ५.
श्रद्धे **१.** १०२, २.
श्रद्धे **१०.** १५१, २[२].
श्रमत् **२.** ३०, ७.
श्रमऽयुवः **१.** ७२, २.
श्रमस्य **१०.** ११४, १०.
श्रमिष्म **२.** २९, ४; **८.** ४, ७.
श्रयध्वं **५.** ५, ५; **१०.** ७०, ५.
श्रयतां **१०.** १८, १२.
श्रयंतां **१.** १३, ६; १४२, ६; **२.** ३, ५; **७.** १७, २; **१०.** ११०, ५.
श्रयंते **७.** ७८, १.
श्रयमाणः **३.** ८, २.
श्रयस्व **३.** ८, २; ३.
श्रयेतां **७.** २, ६.
श्रयेथे इति **१०.** १०६, २.
श्रवः **१.** ९, ७; ८; ४०, ४; ४३, ७; ४४, २; ५१, १०; ६१, १०; ७३, ७; १०; ७९, ४; १०२, २; ७; ११०, ५; ११७, ८; १२६, १; २; ५; १६०, ५; १६५, १२; १७१, ५; **३.** ३७, १०; ५३, १५; १६; **४.** १७, २०; २६, ५; ३१, १५; ३६, ९; ३८, ५; **५.** ७, ९; १६, ४; १८, ५; ३५, ८; ५२, १; ८६, ६; **६.** २, १; ३७, ३; ४६, ५; ४८, १२; ५८, ३; ६५, ३; ६; ७०, ५; **७.** ५, ८; १८, २४; ३४, १८; ८१, ६; **८.** ९, १७; १३, १२; १५, ८; ३१, ७; ४६, २४; ५५, ५; ६५, १२; ७४, ९; ८०, ५; ८९, ४; १०३, ५; **९.** १, ४; ४, १; ६, ३; ७, ९; ९, ९; २०, ३; ३२, ६; ४४, ६; ५१, ५; ६१, १०; ६३, १२; ६६, ७; ८०, २; ८३, ५; ८६, ४०; ९८, ८; १००, ८; **१०.** २७, २१; २८, १२; ५०, १; ६९, ३; ९२, १०; ९३, १०; १०२, ४; १३१, ३; १४०, १; १५५, ५.
श्रवःऽएषे **५.** ६६, ६.
श्रवःऽकामं **८.** २, ३८.
श्रवःऽजितं **८.** ३२, १४.
श्रवःऽभिः **१.** १४९, २; १५६, २; **३.** ३०, ५; ५९, ७; **६.** १, ११; **८.** ५, ३२.
श्रवःऽसु **३.** ३७, ७.
श्रवत् **१.** ३०, ८; १२१, १; **६.** ४५, २३; ५०, ६; **७.** ३२, ५; **८.** १, १५; ८१, ५.
श्रवत् **४.** ४३, १; **७.** ९५, ४; **८.** ४३, २४.
श्रवतः **८.** २४, १०.
श्रवथः **५.** ७४, १.
श्रवथत्ऽपति **५.** २५, ५.
श्रवय **४.** २९, ३; **८.** ९६, १२.
श्रवय **६.** ३१, ५.
श्रवयतं **७.** ६२, ५.
श्रवयत्ऽसखा **८.** ४६, १२.
श्रवयन् **२.** १३, १२.
श्रवयंतः **१.** ११०, ३.
श्रवसः **४.** ४१, ९; **७.** १६, १०; ९०, ७; **१०.** ६१, २४.
श्रवसा **१.** ९२, ८; **३.** १, १६; **६.** ५, ५; १०, ३; ५; **८.** ६, ४८; १०१, १२; **९.** ७०, २; ११०, ५.
श्रवसि **८.** ७४, ९.
श्रवसे **१.** ३१, ७; ५७, ३; ७३, ५; ९५, ११; ९६, ९; १०३, ४; ११३, ६; १२१, १४; १३४, ३; **६.** १७, १४; **७.** १८, २३; **८.** ७०, ९; **९.** ३२, १; ६२, २२; ८०, ३; ९७, २५; ११०, ७; **१०.** ३५, ५.
श्रवस्यः **२.** १०, १; **६.** १, ११.
श्रवस्यतः **६.** ४६, १३.
श्रवस्यता **१०.** ७४, २; १४७, २.
श्रवस्यतां **१.** १३८, ४.
श्रवस्यते **१.** १२८, १; **८.** ४७, १२; ६२, ४.
श्रवस्यन् **१.** १७७, १.
श्रवस्यंतः **१.** १३१, ५.
श्रवस्य **१.** ११७, ९.
श्रवस्यया **१.** १२८, ६.
श्रवस्यवः **१.** ४८, ३; ८५, ८; १२५, ४; १३२, ५[२]; **२.** ३१, १; ७; **४.** १६, १५; **५.** ९, २; **६.** १, ४; ४५, १०; **८.** २४, १८; ५२, ४; **९.** १०, १; ६६, १०; ८७, ५.
श्रवस्यस्य **८.** ९६, २०.

श्रवस्या १. ६१, ५; १४९, ५; २. १९, ७; ६. २७, ६; ७. १८, ११; २३, १; ९. ९६, १६.

श्रवस्यां १. ११७, १०; १८४, ४; ८. १५, ३; १६, २.

श्रवस्याः २. १३, १३; १४, १२.

श्रवस्यात् ४. ४०, २.

श्रवस्यात् ५. ३७, ३.

श्रवस्यांनि १. १००, ५; १०. ४४, ६.

श्रवस्युः १. ५५, ६; ८. ९४, १.

श्रवस्युं ५. ५६, ८; ७. ७५, २.

श्रवांसि १. ११, ७; ३४, ५; ९१, १८; ३. १९, ५; ५४, २२; ५. ४, २; १८, ४; ६१, ११; ६. १९, ३; ७. ७९, ३; ८. ७४, १०; ९९, २; ९. ६३, १; ६७, ५; ८७, ५; १०८, ४; १०. ५९, २; ११६, ६.

श्रवाय्यः १. २७, ८; ३१, ५; ८. ४६, ९.

श्रवाय्यं ५. २०, १; ३८, २; ६. १६, १२; ९. ६३, २३; १०१, ९; १०. ३८, २.

श्रवाय्यंस्य ९. ९७, ५३.

श्रवाय्यां ५. ८६, २.

श्रवाय्यांन् ६. ४५, १२.

श्रवाय्यें १०. १०२, १.

श्रश्राः १०. १७१, ३.

श्रातः १०. १७९, १.

श्रातं १०. १७९, २; ३^{2}.

श्रांतं १. १७९, ३.

श्रांतस्य ४. ३३, ११.

श्रांताय ८. ६७, ६.

श्राम्यंति २. २८, ४.

श्रायंतःऽइव ८. ९९, ३.

श्रायाः ५. ५३, ४.

श्रितः १. ७५, ३; १२५, ५; २. ३, ११; ३. ९, ३; ४. ४३, ७; ५. ११, ३; ८. ३३, ६; ३९, ८; ९. १२, ३; १४, १; ८६, ८; १०. ८५, १.

श्रितं ३. ९, ४; ४. ५८, ११.

श्रिता १. १६४, २९; २. ४१, १७; ५. ६३, ४; ८. ४१, ६.

श्रिताः १. १८७, ४.

श्रितानि २. २८, ८.

श्रिती ९. १४, ६.

श्रियः १. ८५, २; १३९, ३; १६६, १०; २. १, १२; ८, ५; ३. १, ५; ३८, ४; ४४, २; ७. १५, ५; ८. २०, १२; २८, ५; ९२, २०; १०२, ९; ९. १६, ६; ६२, १९; १०. २१, ३; ९१, ५; १२७, १.

श्रियं १. ४३, ७; ४६, १४; ७२, १०; १७९, १; २. १०, १; ४. ४४, २; ५. २८, ४; ४५, २; ७. ६९, ४; ८. १३, २८; २०, ७; ७२, १३; ९. ९४, ४^{2}; १०. ११०, ६.

श्रियसे १. ८७, ६; ५. ५९, ३^{2}.

श्रिया १. ११६, १७; ११७, १३; १२२, २; १८८, ६; २. ८, ३; ३३, ३; ३. ६०, ४; ५. ३, ४; ६१, १२; ६. ४८, १९; ६६, ४; ७. ५६, ६; ७२, १; १०. १, ५.

श्रिये १. ६४, १२; ८१, ४; ८८, ३; ९२, ६; १८४, ३; १८८, ८; २. २३, १८; ४. ५, १५; १०, ५; २२, २; २३, ६; ४१, ८; ५. ३, ३; ४४, २; ५५, ३; ६०, ४; ७४, ६; ६. २९, ३; ४४, ८; ६३, ५; ६४, १; ७. ६७, २; ८. ७, २५; २६, ४; ९. ९४, ४^{2}; १०२, ४; १०४, १; १०. ४५, ८; ७७, २; ९५, ३; ६; १०५, १०^{2}.

श्रिषत् १. १६२, ११.

श्रीः ५. ५७, ६.

श्रीणन् १. ६८, १; ९. १०९, २२.

श्रीणंतः ८. २, ३; ९. १०७, २.

श्रीणंति ९. १, ९; ७१, ४.

श्रीणंति १. ८४, ११; ८. ६९, ३; ९. ८४, ५; ९३, ३.

श्रीणानः ८. १०१, ९; ९. १०९, १७.

श्रीणानाः ९. २४, १; ६५, २६.

श्रीणां १०. ४५, ५.

श्रीणीत ९. ४६, ४.

श्रीणीतन ९. ११, ६.

श्रीणीषे ५. ६, ९.

श्रीणीहि ८. २, ११.

श्रीतः ८. ८२, ५.

श्रीतस्य ९. १०९, १५.

श्रीताः ८. २, २८.

श्रीभिः ६. ६३, ६.

श्रुत १. २३, ८; २. ४१, १५; ६. ३१, ५; १०. ६३, २; १२५, ४.

श्रुतः १. ५३, ९; ५५, ८; २. २०, ६; ४. ३०, २; ३२, २१; ६. ५६, ५; ७. ३२, १७; ८. २२, ५; २४, २; २६, ४; ३३, १०; ६२, ९; ६७, ८; १०. २२, १; २.

श्रुतऽऋषिं १०. ४७, ३.

श्रुतऽकक्षः ८. ९२, २५.

श्रुतं १. ६, ६; १०१, ७; ११६, १३; १२०, ६; १२२, ६; १८४, २; २. ३३, ११; ५. ३९, ३; ५२, १७; ७४, ६; ७८, ५; ६. ४९, ३; ६२, ७; ७. १८, १२; ६२, ५; ६८, २; ८. ९, २७; १३, १०; २६, १७; ५०, १; ५९, ६; ७१, १४; ९३, १६; १०. ३८, ४; १००, १.

श्रुतं १. १२२, ६; १५१, २; २. ४१, ४; ५. ७५, १; ७. ६८, ८; ८. २६, ११; १०. ९२, १३.

श्रुतऽमघं ८. ९३, १.

श्रुतऽरथाय ५. ३६, ६.

श्रुतऽरथे १. १२२, ७.

श्रुतर्यं १. ११२, ९.

श्रुतर्वणि ८. ७४, १३.

श्रुतर्वणे १०. ४९, ५.

श्रुतर्वा ८. ७४, ४.

श्रुतऽवित् ५. ४४, १२.

श्रुतस्य ३. ४६, १; ५. ८५, ५; ६. ४९, १२; ८. २, १३; ९६, ११.

श्रुता ५. ७४, २.

श्रुतां ५. ६२, ५.

श्रुताय २. १४, ८; ५. ८५, १; ६. ३८, ५; ८. ३२, ४.

श्रुतासु ५. ६०, २.

श्रुते ८. ६६, ७; ९. ९७, ५३.

श्रुत्ऽकर्ण १. ४४, १३.

श्रुत्ऽकर्णः ७. ३२, ५.

श्रुत्ऽकर्णं १. ४५, ७; ८. ४५, १७; १०. १४०, ६.

श्रुत्यं १. ११७, २३; १६५, ११; २. ३०, ११; ५. ३०, ५; ६. ७२, ५; ७. ५, ९; ८. ४६, १४; १०. ८०, १.
श्रुत्यस्य १. ३६, १२.
श्रुत्या ६. २१, ६; ३६, ५.
श्रुत्यानि १०. १३८, ६.
श्रुत्यै २. २, ७; ८. ९६, ३; १०. १११, ३.
श्रुत्वा ६. ५०, ५.
श्रुधि १. २, १; १०, ९; ४४, १३; ४८, १०; १३३, ७; १४२, १३; २. ११, १; ५. २४, ३; ६. १७, ३; २१, १०; २६, १; ७. २२, ४; ३८, २; ८. २५, १२; ६६, १२; ८२, ६; ९५, ४; १०. ११, ९; ६१, १४; २१; १२५, ४; १४८, ५.
श्रुधि १. २५, १९; २०; २६, ५; ४५, ३; ५; १२९, २; १३१, ६; २. ६, १; ६. २१, ८; ३६, ५; ४५, ११; ७. ३२, १; ८. ६, १८; २४, १४; ७४, ११; ९९, १.
श्रुधिऽयुतः ६. ६७, ३.
श्रुवत् १. १२७, ३.
श्रुवंतु ६. ४९, १; १०. १५, ५.
श्रुष्टये २. ३८, २.
श्रुष्टिः १. १७८, १; ७. ४०, १; १०. १०१, ३.
श्रुष्टिऽगौ ८. ५१, १.
श्रुष्टिं १. ६७, १; ६९, ४; १६६, १३; २. १४, ९; ३२, ३; ३. ५०, २; ७. १८, ६; १०.
श्रुष्टिऽमंतं १. ९३, १२; ५. ५४, १४.
श्रुष्टी २. ३, ९; ९, ४; १४, ८; ३. ९, ८; ४. ३६, ४; ६. १३, १; ६८, १; ७. ३९, ४; ८. २३, १४; १८; ८७, ६; ९. १०६, १; १०. २०, ६.
श्रुष्टीऽवरीः १०. ३०, ११.
श्रुष्टीवाऽइव ७. ७३, ३.
श्रुष्टीऽवानः १. ४५, २; १२७, ९.
श्रुष्टीवानं १. ११९, १; ३. २७, २.
श्रुष्टीवानाऽइव १०. १०६, ४.
श्रुष्टौ २. १३, ९.
श्रूयते १०. २२, १.
श्रूयाः २. १०, २.
श्रेणयः १०. १४२, ५.
श्रेणिः १०. ६१, २०; ९५, ६.
श्रेणिऽदन् १०. २०, ३.
श्रेणिऽभिः ४. ३८, ६.
श्रेणिं १. १२६, ४.
श्रेणिऽशः १. १६३, १०; ३. ८, ९.
श्रेणीः ५. ५९, ७.
श्रेत् १. १७४, ७.
श्रेयांसः ५. ६०, ४.
श्रेयांसं १०. ३१, २.
श्रेयान् ३. ८, ४; ६. ४१, ४.
श्रेषाम् ४. ४३, १.
श्रेष्ठः १. ४३, ५; १६१, १; २. ३३, ३; ३. २१, ३; ६. १६, २६; २६, ८; १०. १५६, ५.
श्रेष्ठऽतमा १. ११३, १२.
श्रेष्ठऽतमाः ५. ६१, १.
श्रेष्ठं १. ४४, ४; ११३, १; १६४, २६; २. ७, १; ३. २१, २; ४. ३६, ७; ५४, १; ५. ६२, १; ८२, १; ८. ९, १३; १०. २४, २; ३५, ७; ७१, १; ७६, २.
श्रेष्ठया ५. २५, ३.
श्रेष्ठऽवर्चसः ६. ५१, १०.
श्रेष्ठऽवर्चसा ५. ६५, २.
श्रेष्ठऽशोचिषं ८. १९, ४.
श्रेष्ठा ४. १, ६; ६. ६८, २; १०. ६३, १६.
श्रेष्ठानि २. २१, ६.
श्रेष्ठे ६. ७१, २; १०. ३६, १२.
श्रेष्ठेभिः ७. ७७, ५.
श्रेष्ठैः १०. ११२, ३.
श्रोणः २. १५, ७; ८. ७९, २.
श्रोणं १. ११२, ८; २. १३, १२; ४. ३०, १९; १०. २५, ११.
श्रोणां १. १६१, १०.
श्रोणिऽभ्यां १०. १६३, ४.
श्रोत १. १२२, ११; ५. ८७, ८; ९; ७. ३९, ३.
श्रोता १. १७८, ३; ६. २३, ४; २४, २.
श्रोतारः ५. ६१, १५.
श्रोतारं ३. २६, २.
श्रोतुं १. १२२, ६.
श्रोतु ५. ४६, ६.
श्रोतुंऽरातिः १. १२२, ६.
श्रोत्रं १०. ८५, ११.
श्रोत्रात् १०. ९०, १४.
श्रोमतं ७. २४, ५.
श्रोमताय १. १८२, ७.
श्रोमतेन ८. ६६, ९.
श्रोमतेभिः ६. १९, १०.
श्रोषन् १. ६८, ५.
श्रोषंतु १. ८६, ५.
श्रोषमाणाः ३. ८, १०; ७. ७, ६; ५१, १.
श्रोषि ६. ४, ७.
श्रौषत् १. १३९, १.
श्रौष्टीऽइव ८. ४८, २.
श्लोकः १. १९०, ४; ४. २३, ८; ६. २४, १; ७. ३६, ९; ९७, ३; १०. १२, ५; १३, १; १५९, ३.
श्लोकं १. ३८, १४; ५१, १२; ८३, ६; ९२, १७; ११८, ३; १३९, ३; १०; १९०, ३; ३. ५३, १०; ५४, ११; ४. ५३, ३; ७. ८२, १०; ९. ९२, १; १०. ७६, ४; ९४, १.
श्लोकऽयंत्रासः ९. ७३, ६.
श्लोकी ८. ९३, ८.
श्लोकेन ५. ८२, ९.
श्वः १. १२३, ८; १६७, १०; १७०, १; ६. २४, ५; ५६, ६; ७१, ६.
श्वःऽश्वः ८. ६१, १७.
श्वऽघ्नी १०. ४२, ९; ४३, ५.
श्वघ्नीऽइव १. ९२, १०; २. १२, ४; ४. २०, ३; ८. ४५, ३८.
श्वंचयः १०. १३८, २.
श्वंचस्व १०. १८, ११; १४२, ६.
श्वभ्राऽइव २. २७, ५.
श्वऽयातवः ७. १०४, २०.
श्वऽयातुं ७. १०४, २२.
श्वशुरः १०. २८, १.

श्वशुराय १०. ९५, ४.
श्वशुरे १०. ८५, ४६.
श्वशुरेषु १०. ९५, १२.
श्वश्रूः १०. ३४, ३.
श्वश्र्वां १०. ८५, ४६.
श्वसथात् ८. ९६, ७.
श्वसनस्य १. ५४, ५.
श्वसंतः १०. ९४, ६.
श्वसंतं १. १७९, ४; ५. २९, ४; ८. २१, ११.
श्वसिति १. ६५, ५.
श्वसीवान् १. १४०, १०.
श्वा १०. ८६, ४.
श्वात्रऽभाजा ८. ४, ९.
श्वात्रं ८. ६३, ५; १०. ८८, ४.
श्वात्रासः १०. ४६, ७.
श्वात्रेण १. ३१, ४.
श्वान्यं १०. ४९, १०.
श्वान्या १०. १०६, २.
श्वान्याः १०. १६०, २.
श्वानं १. १६१, १३; ९. १०१, १; १३.
श्वानाऽइव २. ३९, ४.
श्वानौ १०. १४, १०; ११.
श्वांतं १. १४५, ४.
श्वांतस्य १०. ६१, २१.
श्वापदः १०. १६, ६.
श्वासय ६. ४७, २९.
श्वितानः ६. ६, २.
श्वितीचयः १०. ४६, ७.
श्वितीची १. १२३, ९.
श्वितीचे २. ३३, ८.
श्वितेषु ८. ४६, ३१.
श्वित्र्येभिः १. १००, १८.
श्वित्यंचः ७. ३३, १; ८३, ८.
श्वित्र्यं १. ३३, १५.
श्वेतः १. ६६, ३; ५. १, ४; ७. ८७, ६; ९१, ३; १०. २०, ९.
श्वेतनायै १. १२२, ४.
श्वेतं १. ११६, ६; ११८, ९; ११९, १०; ३. १, ४; ४. २७, ५; ७. ७७, ३; ९०, ३; ९. ७४, ७; १०. ३९, १०.
श्वेतया ८. २६, १९.
श्वेतऽयावरी ८. २६, १८.
श्वेता ८. ४१, ९.
श्वेतान् ८. ४१, १०.
श्वेतासः ८. ५५, ३.
श्वेतौ ८. ४०, ८.
श्वेत्या १. ११३, २; १०. ७५, ६.
श्वैतरी ४. ३३, १.
श्वैत्रेयः १. ३३, १४.
श्वैत्रेयस्य ५. १९, ३.

ष

षट् १. २३, १५; १६४, ६; १५; २. १३, १०; ३. ५६, २; ६. ४७, ३; ७. १८, १४^{२}; ८. ६८, १४; १७; १०. १४, १६.
षट् १०. १२८, ५.
षट्ऽअक्षं १०. ९९, ६.
षट्ऽअरे १. १६४, १२.
षट्ऽअश्वैः १. ११६, ४.
षट्ऽत्रिंशान् १०. ११४, ६.
षट्ऽभिः २. १८, ४.
षट्ऽविधानाः ७. ८७, ५.
षष्टिः १. १२६, ३; १६४, ४८; ७. १८, १४^{२}; ८. ९६, ८.
षष्टिं १. ५३, ९; ६. २६, ६; ८. ४, २०; ४६, २२; २९; ९. ९७, ५३.
षष्ठ्या २. १८, ५.
षाट् १. ६३, ३.
षोळ्हा ३. ५५, १८.

स

संयती इति संऽयती २. १२, ८; ५. ३७, ५; ९. ६८, ३.
संयत्ऽवीरं २. ४, ८.
संरिहाणे इति संऽरिहाणे ३. ३३, ३.
संवत्सरः १०. १९०, २.
संवत्सरं ७. १०३, १.
संवत्सरस्य ७. १०३, ७.
संवत्सरीणं १०. ८७, १७.
संवत्सरे १. ११०, ४; १४०, २; १६१, १३; १६४, ४४; ७. १०३, ९.
संवयंती इति संऽवयंती २. ३, ६.
संविदाने इति संऽविदाने ३. ५४, ६; ६. ७५, ४.
संवृक्तऽधृष्णुं ९. ४८, २.
संशिश्वरीःऽइव ८. ६९, ११; ९. ६१, १४.
संसत्ऽसु ८. ४५, २५.
संसृष्टऽजित् १०. १०३, ३.
संस्कृतः ८. ३३, ९.
संस्कृतऽत्रं ६. २८, ४.
संस्कृतं ५. ७६, २.
सः १. १, २; ४; ९; ५, ३^{४}; ७, ६; १०, ६; १२, १०; ११; १४, ११; १६, ५; १८, २; ४; ७; २२, ५; २३, १५; २४, २; १२; २५, १२; २०; २६, १; २७, २; ३; ७; ९; ११; १२; ३०, १६^{३}; ३१, १५; ३२, १५; ३६, २; ४; ६; १२; १६; ४०, ४; ४१, १; ५; ६; ४४, ७; ५२, २; ३^{२}; ५४, ३; ७; ११; ५५, २^{२}; ४-६; ५६, ३; ६२, ४^{२}; ६४, १३; ६८, ४; ७०, ३; ७७, २; ३^{३}; ४; ५^{३}; ७९, ५; ६; ११; ८०, २; ८१, १; ८२, ४; ८४, १६; ८६, १; ३; ७; ८७, ४; ८९, १०^{२}; ९३, ३; ९४, २^{२}; १६; ९५, ६; ९६, १; २; ४; ९७, ८; ९८, २; ९९, १; १००, १; ४–८; ९^{३}; १०^{३}; ११; १२; १४; १५; १०२, ९; १०३, २; ३; ५^{५}; १०४, ६^{२}; १०५, ४; ७; ९; १३; १६; १०९, १; ११७, २२; १२१, २; १२२, ९; १०; १२३, ५; १२५, ५; १२७, ३; ६; ११; १२८, २; ४; ५^{२}; ७^{३}; १२९, १; २; ६; १३०, १०; १३२, ३; १४०, ७; १४१, १२; १४३, २; ५; १४४, ५; १४५, १^{५}; ५; १४७, ४; १४९, १; २; ५; १५०, ३; १५३, ३; १५४, ५; १५६, २; १६०, ३; १६४, १६^{२}; २१; २९; ३१^{२}; ३२^{२}; ४६; १६९, १; १७१, ५; १७४, १०; १९०, २; ७; ८; १९१, १०; २. २, ५; ६; ८; ११; ३, ३; ४, ३; ५; ७; ६, ४; ५^{३}; ८; ९, ६; १०, १; १२, १–४; ५^{३}

६–१५; १३, २–५; ६^{२}; ७–१२;
१५, २; ४; ५^{२}; ६; ७; १७, २; ५;
६; १८, १; २^{४}; १९, ३–६; २०,
३–७; २२, १^{२}; २; ३; २३, १७;
२४, १^{२}; ७; ९^{४}; ११; १३; १४;
२५, १; ४; ५; २६, ३^{४}; २७,
१२; ३५, १; ४; ५; ७; १०^{२};
१३^{३}; ३७, १; २; ४१, १०; **३.**
२, २^{२}; ७; १०^{२}; ११; १२; ४,
२; ३; १०; ६, १०; ८, ४; १०,
३^{३}; ४; ८; ११, १–३; १३, १;
३^{२}; ४; १४, १; १६, ३; १८, ५;
१९, १; ३–५; २०, ४; २२, १;
२; २५, २; २६, ३; ३०, ७; ३१,
११^{२}; ३२, ५; ४०, १; ४१, ६;
४५, ५; ४६, २; ५१, ८; ११;
५३, २१; ५५, १७^{४}; ५६, ३; ५९,
२; ८; ६२, ९; **४.** १, २; ५;
८; ९^{२}; १०; ११; २, ९; ४,
६; ७; ८, २^{२}; ३; ४^{२}; ८; ९, २;
३; १२, १; २; १६, ८; १८, ४;
२४, १; २^{४}; ९; २६, ४; २७, २;
३०, २२; ३२, ५; ७; ३६, ५;
६^{५}; ३७, ६^{३}; ३९, ३; ४१, २^{२};
५०, ७; ८; ५१, ४; ५३, ६; ७;
५६, ३; ५७, १; **५.** २, ४; ७;
३, ५; ४, ३; ६; ११; ६, २; ३;
७, ४; ७; ८, ४; ७; ९, १; ७^{२};
११, २; ६; १२, ६; १३, ३; ५;
१५, ३; १६, २; १८, २; २३,
४; २४, ३; २५, १–३; ९; २८,
२; ३३, २; ६; ३६, १; ५; ३७,
४; ४१, १२; ४२, ३; ४४, ३; ८;
१०; १२; १३; ४८, ५; ५३, १५;
५४, ७; ६१, ८; १३; ६५, १^{२};
७७, ४; ८१, ३; ८२, ३; ८३, ५;
८६, १; ८७, ४; **६.** १, ६; ९; २,
४; ५; ३, १; ५; ६; ४, २; ४;
५, ५; ६; ६, २; ६; ७; ९, ३^{३};
४; १०, १; ३; १२, १; ४; ६;
१३, ३; ४; १४, १; १५, २; ३;
१०; १३^{२}; १६, २; १२; २०; २१;
२३; १७, २^{२}; १४; १८, २; ६^{३};
७^{४}; ८; १९, ५; २०, ५; ८; ९;

२१, ३; ४^{२}; ८; १२; २२, ७;
११; २३, ८; २५, ६; २७, ७;
२९, ४; ३१, ५; ३२, २–५; ३३,
४; ३५, ४; ३६, ४; ५; ४३, १;
४४, १; १३; ४५, १; ४; ११;
१५; १७; २०; २१; ४६, २; ४७,
४; १३; २८; २९; ४८, २; ४९,
५; ८; १२; ५१, १४; ५६, २;
६६, ८; ६८, ५^{२}; ६; ७०, ३;
७५, १; **७.** १, १४–१६; २३^{२};
४, २; ४; ८; ५, २; ७; ६, ५; ९,
२; १०, ५; १२, २^{२}; १५, ३; ६;
११; १६, २^{२}; ९; २०, ५; ६^{२};
१०; २१, ५; २२, २; ३२, ६;
१०; ३३, १२; ३८, ३; ४०, ३^{२};
४१, ५; ४२, ४; ४५, २; ३; ४६,
२; ५६, १८; ५९, २; ८; ६०, ९;
६१, १; २; ६२, २; ६६, ५; ६९,
२; ८५, ४^{२}; ८६, ६; ९३, ७; ९५,
३^{२}; ९७, ४; ७^{३}; १०१, १; २; ६;
१०२, १; १०४, १०; ११; १५;
८. १, २२; २७^{२}; २, ३५; ३, ४;
१०; १८; ४, १२; १५; ११, ३;
१३, १; २; १९; १५, ३; १६,
८^{२}; ११; १२; १८, १३; १९, ४^{२};
९^{३}; १०^{४}; १४; ३०; २०, १६;
२१, २; १०^{२}; २३, १२; २१; २४,
२६; २६, २५; २७, १७; ३१, ३;
३२, ५; १२; ३३, १६; ३९, ३;
५^{२}; ६; ७^{२}; ९; ४०, २; ४१, २;
३^{२}; ४^{२}; ५; ८^{२}; ९; १०; ४२, २;
४३, ९; १५; २४; २७; ३२; ४४,
१४; ४६, ४; ९; १२; १३; २१;
४८, ९; ५१, ४; ६; ९; ५२, ५;
५६, ५; ६०, १२; ६१, ९; १५^{३};
६३, १; ३; ४; ७; ६६, ३; ८;
६९, १५; ७१, ३; ५; ९; ७४,
११; १२; ७८, ६; ८७, १; ९०,
४; ९२, १५; ९३, ३; ७; ८^{३}; ९९;
९६, १९^{२}; २०^{२}; ९७, ३; ६; ९८,
१२; ९९, १; ४; १०१, १; १०२,
२; १०३, ४; ५^{२}; **९.** ७, ७; ९,
३; ४; ११, ३; १८, ७; २०, २;
३; ६; ३६, २; ३; ५; ३७, १–६;

३९, ४; ४०, ५; ४१, ५; ४४,
४–६; ४५, १; २; ४६, ५; ४९,
४; ५०, ५; ५५, ४; ५७, ३; ४;
५८, १; ६१, ६; ९; १२; २२;
६२, ८; १०; ६४, १२; ६५, १५;
२७; ६६, २३; ६७, २२^{२}; ३१; ६८,
२; ४; ७०, २; ४–६; ७१, ३; ८;
७२, ८; ७३, १; ८^{२}; ७४, २; ७; ९;
७६, ५; ७७, २^{२}; ७९, ३^{२}; ८०,
३; ८६, १५; ३२; ३८; ४१; ४२;
८७, ३; ८८, २; ९१, ५; ९३, ४;
९६, ३; ८; १०; ९७, ९; २५;
३२; ३८^{३}; ३९; ९८, ४; ९; ९९,
६; ७; १०१, १५; १०४, ५;
१०५, ५; १०७, ११; १०८, २;
१२; १३; १०९, ३; १७; १००,
७; १२; **१०.** १, २; ६; २, ३^{४};
६; ३, ७; ६, १; ४; ७, ४; ८, २;
८; १०, १४; ११, १^{२}; ७^{२}; १४,
१४; १६, १०; १७, ३; ५; २०,
६; २५, १०; २६, ३; ५; २७, १;
२४; २८, २; २९, ७^{२}; ३०, ३;
३१, ४; ७; ८; ३२, ७; ९; ३४,
११; ३५, ७; ३८, २; ४३, ३;
६; ८; ४४, ५; ४६, १; ३; १०;
४८, १०; ४९, ६; ५०, २; ५१,
२; ५२, ३; ५३, १; ३; ११; ५५,
५; ६१, २; ८; ९; १६^{२}; १७; २३;
२६; ६३, १३; ६७, ७; ६८, ९^{४};
१२^{४}; ६९, ३^{४}; ४^{२}; १२; ७०, ९;
७७, ७^{२}; ७९, ४; ८१, १; ७; ८५,
२१; ३४; ८६, १६^{२}; ८७, ८; ८८,
४; ५; ८–१०; १६; ८९, २; ९०,
१; ५; ९१, २; ९३, २; ९; ९६,
३; ७; ९७, ६; १७; २३; ९८,
१; ५; ९९, २^{२}; ३–६; ७^{२}; ८; ९;
१२; १००, ९; १०१, ८; १०३,
३^{३}; १०७, ६; १०८, ४; १०९, ५;
११०, ३; १११, १; ३; ११२,
५^{२}; ११४, ४^{३}; ११५, ५; ११७,
२–४; ६; ११८, ३; ८; १२१, १;
१२२, १; ५; १२३, ५; १२५, ४;
१२८, ८; १२९, ७; १३९, २;

१४०, ४; १४७, ४[२]; १४९, ३; १५३, ५; १६४, ५; १८६, २; १८७, १; १९१, १.

सका १. १९१, ११.

सकृत् १. १०५, १८; २. १६, ८; ६. ४८, २२[२]; ६६, १; ८. १, १४; १०. ३३, ३; ९५, १६.

सकृत्ऽस्वं १०. ७४, ४.

सऽकेताः ६. ९, ५.

सक्तुंऽइव १०. ७१, २.

सक्थानि ५. ६१, ३.

सक्थि १०. ८६, ६; ७.

सक्थ्या १०. ८६, १६.

सकर्मन् १. ३१, ६.

सक्म्यं ३. ३८, ७.

सऽक्रतवः २. २७, २.

सऽक्रतुः १०. १४८, ४.

सक्रंतू इति सऽक्रंतू १. ९३, ५.

सक्षणः ५. ४१, ४.

सक्षणिं १०. ३२, १.

सक्षणिः २. ३१, ४; ८. २४, २६; ९. ११०, १.

सक्षणिं १. १११, ३; ८. ७०, ८; ९. ७१, ४; ७८, ३.

सक्षणी इति ८. २२, १५.

सक्षत् १. १२९, १०; ५. ३०, ६.

सक्षत ८. १३, २८.

सक्षतः १. १३१, ३.

सक्षि ५. ३३, २.

सऽक्षितः ६. ४४, ६.

सऽक्षित्तौ १. १४०, ३.

सक्षीमहि ७. ३९, ६; ५१, १; ५४, ३.

सक्ष्व १. ४२, १.

सखा १. ४, १०; २२, १९; २६, ३; ३१, १; ५३, २; ६३, ४; ७२, ५; ७५, ४; ९१, ८; १५; १७; १००, ४; १७०, ३; १८७, ३; २. १, ९; २०, ३; २४, १; २८, १०; ३. ४, १; ३१, ८; ३९, ५; ४३, ४; ५४, १७; ४. ४, १०; १६, १८; १७, १७; १८; २५, ६; ३१, १; ५२, २, ३; ५. २९, ७; ६. ३३, ४; ४५, १; १७; ५५, ३; ५; ७. १८, ६; १९, १०; २०, ८; ५५, १; ८८, ६; ८. २, ३९; ४, ९; १३, ३; १७, १४; ४३, १४; ४५, १; ३७; ७०, ११; ९३, ३; १००, २; ९. ६६, १; ४; ८६, १६; ९६, २; १०१, ६; १०. १०, २; २५, ९; २६, ७; ८; ४२, ११; ११७, ४; १३६, ४–६; १५२, १; १६८, ३; १८६, २.

सखाऽइव ३. १८, १; ८. ४८, ४; ९. १०४, ५; १०५, ५.

सखायः १. ५, १; २२, ८; ३०, ७; ५३, ११; १६५, ११; ३. ९, १; ३०, १; ३१, १७, ५५, २२; ४. १२, ५; ३२, ६; ५. ७, १; १२, ५; ३१, १०; ३२, १२; ५२, २; ६. २१, ५; २६, ८; ४५, ४; ७. १९, ८; २१, ९; ३१, १; ६८, ७; ८. १, १; २, १६; २१, २; ९; २४, १; १९; ४५, १६; ७०, १३; ९२, ३३; ९६, ७; १००, ५; ९. ४५, ५; ९६, ४; ९७, ८; ४३; १०१, १; १०४, १; १०. ७१, २; ७, ८; १०; ८५, २३; ८८, १७; १७९, २.

सखायः १. ४१, ७; १६५, १३; ३. २९, ९; ५. ४५, ६; ६. १६, २२; २३, ९; ४८, ११; ७. ९७, २; ८; ८. २०, २३; ९. ९८, १२; १०५, १; १०. ३०, १४; ५३, ८; १०१, १; २; १०३, ६.

सखायं १. १२९, ४; १८५, ८; ४. १, ३; २४, ६; ५. ३१, १२; ८५, ७; ६. ४५, ७; १९; ५५, २; ७५, ३; ७. १८, ६; ३४, १५; ८६, ४; ८. २, २७; ४५, ३७; ६१, ११; ६२, ६; १०. ७, ३; ८, ७; १०, १; २७, ६; ४२, २; ७१, ६; ८७, २१; ८९, ३; ११७, ३; ६.

सखाया १. १६४, २०; ३. ३५, ४; ४३, १; ४; ४. ४१, ३; ६. ४०, १.

सखायौ ६. ६०, १४.

सखिऽत्वनाय ६. ५१, १४; ८. १२, ६.

सखिऽत्वं ३. १, १५; ४. २५, २; ८. २१, ८; ९. ३१, ६; ६१, ४; ६५, ९; ६६, १४; १०. १३३, ६.

सखिऽत्वे १. १०, ६; ८. ७, ३१.

सखिऽभिः १. १००, २; ४; १८; ३. १, ९; ३९, ५; ४७, ३; ५१, ८; ४. १६, ६; ३२, ३; ६. ३२, ३; १०. ६७, ३; ७; ७३, ५; ६; ११२, ३.

सखिऽभ्यः १. ४, ४; ५३, २; ७५, ४; ८०, ६; ३. ३०, १५; ३१, १५; ३२, १६; ६२, १; ४. २३, ५; ६; ५. २४, ४; ६. ४४, ७; ७. २७, २; ४; ९५, ४; ९७, ७; ८. ९६, २१; ९. ४५, २; ६६, १; ४; ९६, १; १०. ६, २; ३४, २; ५; ४२, ११; ८१, ५.

सखिऽयतः १. १३१, ५.

सखिऽयतां ४. १७, १८.

सखिऽयते १. १२८, १; ८. ४०, ३; १०. ९१, १.

सखिऽयन् ३. ३१, ७; ५. ४९, १; ६. ३२, ३.

सखिऽवान् १. १५६, ४.

सखीन् १. १६५, १३; ३. ४, १; ३१, ८; ४. ३५, ७; ५. ५३, १६.

सखीनां १. ३०, ११; ४. ३१, ३; ५. ६४, ५; ७. ३२, २५; १०. ११२, १०.

सखे १. ३०, १०–१२; ३. ५१, ६; ४. १, ३; १८, ११; ३५, ३; ८. ७१, ९; १०. ८७, २१; ११२, १०.

सख्यं १. १५, ५; ६२, ९; ८९, २; १३८, ४; १६३, ८; २. १८, ८; ३. ३१, १४; ४३, २; ५८, ६; ६०, ३; ४. २३, ५[२]; ६; २५, १; ७; ३३, २; ५. ५०, १; ६. १८, ५; ४५, २६; ४८, १८; ७. ७, २; १८, १२; २१; ३६, ५; ८२, ८; ८. १०, ३; १३, २१; १९, ३०; ४४, २०; ४८, २; ६८, ८; ११; ७२, २; ९६, ७; ९. ५६, २; ८६, ९; ९७, ५; ११; १०. १०, २; ४०, ७; ४२, ४; ६१, १०; ६२, १.

सख्यस्य १. २६, ५; ५. ५५, ९; ८. ४४, २२.
सख्यां १. ५३, ७; ६. २१, ७; ५६, २; ८. ४३, १४; ४८, १०; १०. ५०, २; ७१, १०.
सख्या १. ७१, १०; १०८, ५; १७८, २; २. ३२, २; ३. ५८, ६; ४. ३, ४; १०, ८; १६, २०; ६. ४७, १७; ६१, १४; ७. २२, ९; ७२, २; ८८, ५; ८. ८६, १; १०. ६, २; १०, १; २३, ७; ४८, ९.
सख्यात् १०. १२४, २.
सख्यानि १०. ७१, २; ९५, १५; ११३, ९.
सख्याय १. १०१, १–७; ११९, ५; १३८, २; १६७, ४; ४. १७, १६; २२, २; ३१, ११; ३३, ११; ४१, २; ३; ७; ५५, ३; ५. २९, ११; ६. २९, १; ५७, १; ६०, १४; ७. १८, १२; ८. २१, १४; ८९, २; ९८, ३; ९. ६६, १८; ८६, २०; १०७, २०; १०. २९, ८; ३६, ७; ६१, २५; ६४, ७; ७३, ४.
सख्युः १. ७२, ५; ३. ४३, ४; ४. ३, १३; ८. १, १६; ४५, ३६; ६९, ७; ९. ८६, १६; ९६, २२; १०. ३, ४; ८६, १२.
सख्ये १. २६, ३; १६५, ११; २. ३५, १२; ३. १८, १; ५. २९, ७; ७. ६७, ७; ८. ४८, ४; ९. १०४, ५; १०५, ५; १०. ११७, ४.
सख्ये १. ११, २; ९१, १४; ९४, १–१४; १३८, ३; ३. ९, ३; ५४, २१; ४. १६, १०; १७, ९; २८, १; ५. १६, ३; ४४, १४; ६. २७, १; २; ४४, ११; ७. ५४, २; ८. ४, ७; २१, १५; ७१, १३; ९. ६१, २९; ६६, १४; १०७, १९; १०. २५, १; ४८, ५; ७१, ५; ८८, २; १२४, ९.
सख्येभिः ३. १, १९; १०. ११३, ९.
सख्येषु १. १०, ५; १०. १३८, १.
सख्यैः ६. १९, १३; १०. १३२, २.
सङ्गणः १. १०१, ९; ३. ३२, ३; ४७, २; ४; ५२, ७; १०. १५७, ३.
सगरस्य १०. ८९, ४.
सघत् १. ५७, ४.
संकाः ६. ७५, ५.
संगच्छमाने इति संऽगच्छमाने १. १८५, ५.
सचंत ४. ५, ९.
सचत १०. ७५, ५.
सचतां १. १८३, २.
सचते १. ९१, १४; १२५, १; १४०, ९; १४५, २; १८०, ५; २. १८, २; ४. ७, ११; १२, २; ५. ३४, ५; ४४, ३; ६. २८, ३; ८. ४, ६; ९; ६०, १८; ९. ७४, १; ७; ८६, ८; ९३, ३.
सचथाय १. १५६, ५.
सचथ्यै ८. १०१, ५.
सचथ्यैः ५. ५०, २.
सचध्यै १. १६७, ५.
सचनः १. ११६, १८.
सचनःऽतमा ८. २६, ८.
सचनस्य ६. ३९, १.
सचनस्यमाना १०. ४, ३.
सऽचनाः १. १२७, ११.
सचनाऽवंतं ८. २२, २.
सचंत १. ७३, ४; १०. १११, ७.
सचंत १. १५६, ४; १६४, ५०; २. ५, ५; ३. १, १४; ५. १७, ५; ४३, १५; ७. ५, ४; ७४, ५; १०. ९०, १६; १७२, १.
सचंतां १. २२, ११; ९८, ३; ४. ५, १४; ४१, १०; ७. १०४, १४; १०. ८९, १५.
सचंते १. ५९, ६; १३४, २; ३. १३, २; ७. ९१, ६; १०. ५, ४; ६४, ७.
सचंते १. ६०, २; ७१, ७; १००, १३; १२३, ८; १९०, २; ३. ४०, ७; ४. ४२, १; ४४, २; ७. ५, ५; ३३, ७; ६१, ५; ७२, १; ९०, ५; ९. ८२, ५; ८९, ५; ९५, ४; १०. १२४, ८.
सचमानः ९. ७४, ५; ९६, १९; १०. ३, ३.
सचमानाः ५. ४२, ८.
सचमानाय १०. ११७, ४.
सचमानौ ५. ३६, ६.
सचसे ४. ११, ६; १०. ८, ६.
सचसे २. १, ३; ५. २८, २.
सचस्यमानः १०. ८, ७.
सचस्व १. १, ९; १२९, ९[2]; ६. २४, १०.
सचस्व ३. ५३, १७; ५. ३१, २.
सचा १. ५, २; ७, २; ९, ३; १०, ४; ४०, १; ५१, ११; ६२, ३; ७१, ४; ८१, ८; ८३, ५; ९३, ११; १२२, ८; १३०, १; १३५, ३; १३९, ७[2]; १४०, ७; १६१, ५; १६७, ७; १७४, ६; २. १७, ७; ३. १२, २; ५३, १०; ५४, २; ६०, ४; ४. १, ३; ३, ९; ५, १०; ३१, ५; ३२, ३; ४; ३७, ३; ५०, ११; ५. १६, ५; १९, ४; ४४, १२; ४८, ४; ५६, ८; ९; ६५, ३; ७४, २; ६. २४, १; २६, ४; ६; ४५, २२; ५७, ४; ५९, ३; ७. १, २१; २२; २२, ४; ३२, २; ५९, ३; ८१, २; ९३, ८; ८. १, १; ४, २; ३; २१, १५; २५, २४; ३२, २०; ३३, ४; ७; ४६, ७; ५१, १; ५२, १; ६१, ११; ६६, ६; ६८, १७; ७८, २; ९२, २९; ९३, २०; ९७, ८; ९. १०, ८; ७०, ४; १०. २३, ४; ५०, ७; ६२, ६; ९३, ५; ९५, ८; १०५, ४; ९; १३१, ४; १३४, ४.
सचानः ६. २०, २.
सचाऽभुवः ८. ३१, १०.
सचाऽभुवं १. १११, १; १३१, ३[2].
सचाऽभुवा १. ३४, ११; १५७, ४; २. ३१, १; ८. ३५, १–३; १०. ७६, १.
सचाऽभुवे १०. ११७, ४.
सचाऽभूः १०. ७०, ९.
सचावहै इति ७. ८८, ५.
सचावहै ६. ५५, १.
सऽचितः १०. ६४, ७.
सचिऽविदं १०. ७१, ६.
सचेत ५. ५२, १५; ८. १०२, २२.

सऽचेतसः ८. ५८, १; १०. १, ३; ४, ५; ६४, ७.
सऽचेतसं १०. ४४, ४.
सऽचेतसा १०. ११३, १.
सऽचेताः १. ६१, १०; ४. १६, ७.
सचेतां १. १८५, ९.
सचेते इति २. ४१, ६.
सचेते इति १. १३६, ३; ३. ३९, ३.
सचेथे इति ८. ५, २.
सचेथे इति १. ११६, १७; १५२, १; १८०, १; १८३, २; २. ३९, २; १०. १०६, १०.
सचेमहि ५. ५०, २; १०. ७, १.
सचेमहि १. १३६, ६^{२}; २. ८, ६; ८. २५, ११; १०. ५७, ५; ६; ६४, ११.
सचेय ८. १९, २८; ४८, १०.
सचेवहि ८. ६९, ७; १६.
सऽजन्या ४. ५०, ९.
सऽजाताः १०. १०३, ६.
सऽजातान् १. १०९, १.
सऽजात्यं २. १, ५; ३. ५४, १६; ८. २७, १०; ७३, १२.
सऽजात्यस्य १०. ६४, १३.
सऽजात्यानां ८. ८३, ७.
सऽजात्ये ८. १८, १९.
सऽजात्येन ८. २०, २१.
सजामि १. १९१, १०.
सऽजित्वरीः १०. ९७, ३.
सऽजित्वानं १. ८, १.
सऽजित्वाना ३. १२, ४.
सऽजूः १. २३, ७; ४४, २; १४; ५. ५१, ८^{२}; ९^{२}; १०^{२}; ६. ४७, २९; ७. ३४, ८; ८. ९७, १०; १०. ७५, ६; १०५, ९.
सऽजोषः ६. २, ३.
सऽजोषसः १. ४३, ३; १३१, १; १३६, ४; १७३, ७; २. ११, १४; ३. ८, ८; २०, १; २२, ४; ४. ३४, ६; ८^{४}; ५. २१, ३; २३, ३; ५७, १; ८. २३, १८; २५, १४; २७, ५; १७; ५४, ३; ९. ५, ११; १८, ३; ८१, ४; १०२, ५; १०. ६५, १; १२६, १; १७५, ३.
सऽजोषसः २. ३१, २; ५. ५४, ६; १०. ३५, ११.
सऽजोषसं १०. १५३, ४.
सऽजोषसा ३. ५८, ७; ४. ४६, ६; ७. ७२, २; ८. ९, १२; २६, ११; १०१, ७.
सऽजोषसौ ८. ३५, १.
सऽजोषाः १. ६५, १; ७२, ६; ९०, १; ११८, ११; १५३, १; १८६, २; ३; ६; २. ३१, ४; ३. ४, ८; ३२, २; ३५, ९; ४३, ३; ४७, २; ४. ५, १; ३४, ७^{४}; ३९, ३; ५६, ४; ५. ४, ४; ३१, ५; ४१, २; ४; ८; ४३, ६; ६. ३, १; १२, १; ४०, ५; ४९, ७; १०, [illegible] १३; ५१, ५; ६७, ५; ६८, १; ७. ३, १; ५, ९; १०, ४; २४, ४; ३४, २३; ३८, ४; ४८, ४; ६०, ४; ८. ४८, १५; ६३, १२; १०. १८, ६; २०, १०; ६१, २७; ८३, २; ११०, ३.
सऽजोषौ ३. ६२, २.
संचरंती इति संऽचरंती १. १४६, ३; ३. ३३, ३.
संज्ञातऽरूपः १. ६९, ५.
सत् १. १६४, ४६; २. ४१, १०; ४. ५, १०; ५. ४४, ३; ६. १८, ४; २४, ५; २७, २^{५}; ७. १०४, १२; ८. ७३, १; ९. ६१, १०; १०. ५, ७; ७२, २; १२९, १.
सतः १. ३६, ३; ९६, ७; ४. ६, ६; ७. ३२, २४; ८७, ६; १०४, २१; ८. २३, २६; १०१, ११; ९. १९, ७; २१, ७; ३१, ६; ८६, ५; ६; १०. २७, ४; ५३, १०; १२९, ४.
सतःऽमहांतः ८. ३०, १.
सतःऽवीराः ६. ७५, ९.
सतःऽसंतः ३. ३१, ८.
सत्ऽअश्वः ५. ५८, ४.
सता ८. ४३, १४.
सतां १. १७३, ७; २. १, ३; १६, १; ६. ६७, १.
सती २. १७, ७; ४. ३, ९; ६. ४७, २०; ८. ५, १.
सतीः १. १६४, १६; ३. ३१, ५; ५. २९, ५; ८. ६, ८; १४, ८; ९. ८७, ८; १०. १६९, ४.
सतीनऽकंकतः १. १९१, १.
सतीनऽमन्युः १०. ११२, ८.
सतीनऽसत्वा १. १००, १.
सते १. १२४, १२; ५. ७, ४; ६. ४७, २०; १०. ११५, ६.
सत्तः १. १०५, १३; १४; २. ३६, ६; ३. ४१, २; ७. ४२, २; ५६, १८.
सत्ता ३. १७, ५; ९. ८६, ६; ९६, २३.
सत्ऽपतिः १. ५४, ७; ९१, ५; १००, ६; १३०, १^{२}; १७४, १; २. १, ४; ३. ३४, ७; ५. २७, १; ४४, १३; ६. १३, ३; १६, १९; ५६, २; ८. १९, ३६; १०. ८, ९; ४३, ९.
सत्ऽपतिं १. ११, १; २. ३३, १२; ५. २५, ६; ३२, ११; ८२, ७; ६. १४, ४; २६, २; ४६, १; ८. २, ३८; २१, १०; ५३, ६; ६९, ४; ७४, १०; १०. ६०, २.
सत्पंती इति सत्ऽपंती ५. ६५, २; ६. ६०, ६; १०. ६५, २.
सत्ऽपतीन् ६. ५१, ४.
सत्ऽपते ६. ४६, ३; ८. ६८, १.
सत्ऽपते १. ५३, ६; १६५, ३; ३. ४०, ४; ६. ५१, १३; ८. १२, ८; १८; १३, १२; ३६, १; ६१, १७; ९३, ५; १०. ५०, २.
सत्य १. २९, १; ६. ४५, १०; ८. ९२, १८; ९८, ५.
सत्यऽउक्तिः १०. ३७, २.
सत्यः १. १, ५; ६३, ३; ७३, २; ८७, ४; १४५, ५; १५२, २; १६७, ७; १७४, १; २. १२, १५; २२, १–३; २३, ११; २४, १४; ३. १४, १; ४. १६, १; २१, १०; ३१, २; ४०, २; ५. २३, २; २५, २; ६. २२, १; ६७, ८; ८. २,

३६; ३, ४; ११, ८; ९०, २; ४; ९. ७, ३; ९२, ६; १०. २९, ४.

सत्यऽकर्मन् ९. ११३, ४.

सत्यऽगिर्वाहसं १. १२७, ८.

सत्यऽतर १. ७६, ५.

सत्यऽतरः ३. ४, १०.

सत्यऽताता १०. १११, ४.

सत्यऽताते ४. ४, १४.

सत्यऽधर्मा १०. ३४, ८; १२१, ९.

सत्यंऽधर्माणः ५. ५१, २.

सत्यऽधर्माणं १. १२, ७.

सत्यंऽधर्माणा ५. ६३, १.

सत्यऽध्वृतं १०. २७, १.

सत्यं १. १, ६; ३८, ७; ५२, १३; ९८, ३; १०५, १२; १५९, ३; १८५, ११; २. २२, १–३; २४, १२; ३. १४, ६; ३०, ६; ३२, ९; ३९, ५; ५४, ३; ४. १, १०; १८; १७, ५; १०; २८, ५; ३३, ६; ५४, ४; ५. ७३, ९; ८५, ८; ६. ३०, ४; ७. ५६, १२; ६०, १; १०४, १२; ८. ३३, १०; ४०, ११; ४५, २७; ४६, २; ५९, ३; ५; ६२, १२; ७४, १५; ९३, ५; १००, ३²; ९. ६४, २; ९२, ५; ११३, ४; १०. २७, १०; ४७, ४; ५५, ६; ८७, १२; १०९, ६; ११७, ६; १७०, २; १९०, १.

सत्यऽमं[illegible]ा ८. २, ३७.

सत्यऽमंत्राः १. २०, ४; ७. ७६, ४.

सत्यऽमन्मा १. ७३, २; ९. ९७, ४८.

सत्यंऽउग्रस्य ९. ११३, ५.

सत्यऽयजं ४. ३, १; ६. १६, ४६.

सत्ययां १०. ६३, ११.

सत्यऽयोनिः ४. १९, २.

सत्यंऽराधः ७. ४१, ३.

सत्यऽराधः १. १०१, ८.

सत्यऽराधसे ७. ३१, २.

सत्यऽराधाः ४. २४, २; २९, १; ५. ४०, ७; १०. २९, ७; ४९, ११.

सत्यऽवाचः ३. ५४, ४.

सत्यऽवाचं ३. २६, ९; ७. २, ३.

सत्यऽवाचा १०. १२, १.

सत्यऽशावसः १. ८६, ८; ९.

सत्यऽशंवसं ५. ५२, ८.

सत्यऽशुष्म १०. ११२, १०.

सत्यऽशुंष्मः ३. ३०, २१; ४. ११, ४; ९. ९७, ४६.

सत्यऽशुंष्मं १०. ४४, ३.

सत्यऽशुंष्माय १. ५१, १५; ५७, १; ५९, ४; १०३, ६.

सत्यऽश्रंवसि ५. ७९, १.

सत्यंऽश्रुतः ५. ५७, ८; ६. ४९, ६.

सत्यऽसत्वन् ६. ३१, ५.

सत्यऽसंवं ५. ८२, ७.

सत्यऽसंवस्य १०. ३६, १३.

सत्यस्य २. १५, १; ७. ३५, २; ८. ५७, २; ६९, ४; ९. ७३, १.

सत्या १. ७०, ४; २. १५, १; ४. १, ७; १७, २०; २२, ६; ५. ४५, ७; ६. ६५, ५; ७. ७५, ७; ८३, ४; ७; ९. ९४, ४; १०. २२, १३; ५६, ३; १२८, ४.

सत्याः १. ७९, १; १७९, ६; १८०, ७; ५. ६७, ४; ६. ५०, २; ७. १७, ५; ८. ४४, २३; ५७, २; १०. ११६, ८.

सत्यानि ६. ६७, १०; ९. ७८, ५.

सत्यानृते इति ७. ४९, ३.

सत्याभिः १. १२९, ७.

सत्यां १. १०८, ६; ९. ७०, १; १०. ६७, ११; १०४, ३.

सत्यासः १०. १५, १०.

सत्ये ९. १०९, ६.

सत्ये इति ३. ६, १०.

सत्येन १. २१, ६; ७. ९०, ५; ९. ११३, २; १०. ६७, ८; ८५, १.

सत्येभिः ७. ७५, ७; १०. ६७, ७.

सत्यैः १. ६७, ३; १०. १५, ९; १११, १.

सत्रा १. ५७, ६; ७१, ९; ७२, १; २. २०, ७; ८; ३. ५१, ६; ४. १७, ६³; २१, ७; २२, ९; ३०, २³; ५. ६०, ४; ६५, ५; ६. २०, २; २५, ८; ३४, ४; ३६, १³; २; ४६, २; ७; ७. २५, ५; ३१, १२; ३२, १६; ९३, ५; ८. २, ३०; १५, १०; ११; ४६, ११; ९७, १३; १०१, १२; १०. ९६, १३; ११३, ५; ११६, ४.

सत्राऽकरः १. १७८, ४.

सत्राचः १०. ७७, ४.

सत्राचा ७. १००, १; ८. २, २७; ९. ७७, ४.

सत्राचीं ७. ५६, १८.

सत्राच्या ८. ६१, १.

सत्राऽजित् ८. ९८, ४; ९. २७, ४.

सत्राऽजितः ८. ३, १५.

सत्राऽजितं २. २१, १.

सत्राऽदावन् १. ७, ६.

सत्राषाट् ७. २०, ३.

सत्राऽसहः २. २१, ३.

सत्राऽसहं १. ७९, ८; ३. ३४, ८; ५१, ३; ८. ९२, ७.

सत्राऽसहे २. २१, २.

सत्राऽहनं ४. १७, ८.

सत्राऽहं ५. ३५, ४.

सत्राऽहा ६. ४६, ३.

सत्रे ७. ३३, १३.

सत्वनं १०. ११५, ४.

सत्वनां ८. ९६, ४; १०. १०३, १०.

सत्वने ६. ४५, २२; ८. ४५, २१.

सत्वनैः ५. ३७, ४.

सत्वंऽभिः १. १३३, ६²; १४०, ९; २. २५, ४; ३०, १०; ३. ३९, ५; ४९, २; ५. ३४, ८; ८. ४५, ३; ९. ३, ४; ७६, १; १०. १५५, १.

सत्वा १. १७३, ५; ४. १३, २; ४०, २; ५. ३३, ५; ६. १८, २; २२, १; २९, ६; ३७, ५; ७. २०, ५; ८. १६, ८; ९. ८७, ७.

सत्वानः १. ६४, २.

सत्वानं ८. ४०, १०; ११.

सत्संत् १०. ५३, १.

सत्सि ८. ११, १०.

सत्सि १. १२, ४; ७६, ४; २. ६, ८; ३. १४, २; ६. १६, १०; ८. २३, २६; १०. ३, ७; ४४, ५.

सद २. ३६, ४; ७. ११, १; ८. ९७, ८; १०. ७०, ३.

सद॑ः १. ८५, २; ६; ७; १२८, ३; ५. ६१, २; ६. १६, १७; ८. २९, ९; ४१, ९; ९. ७०, २; ९२, ३; १०७, १०; १०. ९६, २; १३०, २.

सदुः ३. २४, ३; ८. १७, १; ७५, १; ९. २, २; ५५, २; १०६, ७; १०. ४३, २.

सद॑ःऽसदः १०. १५, ११; ७६, १.

सद॑ःऽसु ७. ८५, ३.

सदत् १. १२८, १; ३. १३, १; ८. १३, २४; १०. ९९, ३.

सद॑त ७. ५९, ६.

सदत ७. ५७, २; १०. १५, ११.

सदतन २. ३६, ३.

सद॑तं ७. ९१, ४.

सदतं ४. १६, १०; ५. ७२, १; २.

सदतां ५. ७२, ३; ७. ४२, ५; १०. ७०, ६.

सदतु ७. ९७, ४.

सद॑थः ५. ६७, २.

सदन् ४. ३, ११; ८. ६३, २.

सद॑नं १. ९६, ७; १०४, ५; ११७, १०; १३६, २; २. २३, १; ४०, ४; ३. ३१, ९; १२; ५४, ६; २१; ६. ७, २; ९. ७१, ६; १०. १३५, ७.

सदनऽसदे ९. ९८, १०.

सदनऽस्पृशः ९. ७२, ८.

सद॑ना १०. १८, १३.

सद॑नात् १. १६४, ४७; ४. २१, ३; ७. ३६, १.

सद॑नानि १. ५५, ६; ११३, २; १८१, ५; ९. ९१, १.

सद॑नाय ५. ४७, ७; १०. ९३, ५.

सद॑नी १. १८६, ११.

सद॑ने १. ३१, १७; ५३, १; ८४, ४; ९५, ८; १२२, ६; १४४, २; १४८, ३; १६९, ६; १८९, ४; ३. ३०, ९; ३४, ७; ५१, ३; ४. १०, ८; ४२, ४; ५. ४३, १२; ४७; १; ६. ११, ५; ४०, ५; ७. २४, १; ३६, ३; ८. १३, २; १९, १५; २७, ५; ५९, ४; ९७, ५; ९. १२, १; ३; ७२, ६; ७७, ४; ९२, २; १०. ११, ९; १२, ७; ३८, २; ४३, ७; ६८, ७; ७५, १; १००, १०; १४३, ४.

सद॑ने इति॑ ७. ५३, २.

सद॑नेषु १. ५६, ६; २, ३४, १३; ४. २१, ५; ५. ३०, ११; ८. ९, १०; ९. ८६, ११.

सद॑तः ४. २१, ६; १०. ६१, १३.

सद॑ता ७. ७०, ३.

सद॑तु १. १८६, ८; ३. ४, ८; ७. ४३, ३; ८. २७, ६; १०. ११०, ८; १४२, ६.

सदन्यै १. ९१, २०.

सद॑ं १. २७, ३; ३६, २०; ८९, १; १०६, ५; ११४, ८; ११६, ६; १२२, १०; १२९, ११; १८५, ८; २. १४, १; ३४, ४; ३. २, १५; ४. १, १; २, ५; ३, १२; १३; ७, ७; १२, ५; ५. ७७, ४; ८५, ७; ६. १, ५; १२; ५०, ९; ६७, ८; ७. २, ३; ११, २; ४१, ७; १०. ४, ७; ७, ३; ९३, १; ९४, १०.

सद॑सः १. १८, ६; १८२, ८; २. १७, ७; ३. ३६, ६; ४. १७, ४; ५१, ८; ५. ८७, ४; ६. १७, ५; १०. ९४, १२; १११, २.

सद॑सि १. ४७, १०; १८१, ८; २. ४१, ५; ३. १, १४; ७, २; ५५, १२; ५. ४१, १; ९. ४०, २.

सदस्पती इति॑ १. २१, ५.

सदा॑ १. १२, २; २२, २०; २४, ३; २६, २; ११७, २३; १२५, ५; १२९, ९; १४०, ९; ३. ३, ८; ११, ५; ५४, २१; ४. १, ८; ५. ४१, ९; ७३, ५; ६. ४५, ३३; ७. १, २०; २५; ४, ४; २२, ५; ३४, २५; ३७, $८^{२}$; ५६, २५; ८३, ९; ८. १, २०; ४, ९; १९, २८; २०, २२; २३, २८; २५, २१; ४४, २०; २९; ४६, ५; ५०, ६; ५३, ८; ८३, २; १०३, ५; ९. ११०, ४; १०. १, ७; ११, ५; ६४, ११; ९३, ११.

सदा॑ंसि ३. ३८, ६; ५४, ५; ९. ९१, ४.

सऽदा॑नः ७. ३३, १२.

सदान्वे १०. १५५, १.

सदाऽपृणः ५. ४४, १२.

सदाम ७. १, ११; ४, ६; ८. २१, १५.

सदाऽवृध ५. ३६, ३.

सदाऽवृ॑धः ४. ३१, १; ८. २४, १६; ९. ४४, ५.

सदाऽवृ॑धं ८. १३, १८; ६८, ५; ७०, ३.

सदाऽवृ॑धा ८. १८, ६.

सदाऽसहं १. ८, १.

सदाऽसाः ४. १६, २१.

सदाऽसात॑मं ४. ३७, ५.

सदाऽसां ७. ३९, ६.

सऽदि॑वः २. १९, ६.

सऽदृङ् १. ९४, ७; ८. ११, ८.

सऽदृशी॑ः १. १२३, $८^{२}$; ३. ३५, ३; ५२, ८; ४. ५१, ६; ६. ४७, २१.

सदेम ६. १, ६; ७५, ८; १०. १६९, ४.

सद्म॑ १. ३८, १०; ७३, १; १७३, ३; ३. ५५, १४; ४. १, ८; ९, ३; ५. ८७, ७; ६. ११, ५; ६७, ७; ७. १८, २२; ९. ७, ३; ८३, ५; ९७, १; १०. २०, ५; ६७, १०; ९६, १०.

सद्म॑ऽइव १. ६७, ५; २. १५, ३; ९. ९२, ६.

सद्म॑न् १. १५१, ५; ७. १८, ११; ४२, २; १०. १०५, ९.

सद्म॑नः ६. ४७, २१.

सद्म॑नी इति॑ १. १८५, ६.

सद्म॑नोः ३. ५५, २.

सद्म॑ऽबर्हिषः १. ५२, ४.

सद्म॑ऽमखसं १. १८, ९.

सद्म॑ऽसु १. १३९, २; ५. २३, ३.

सद्माने १. १७३, १; ६. ५१, १२.

सद्मा॑नि १. १३९, १०; ६. ३०, २; १०. १, १.

सद्मः १. ५, ६; ८, ९; २७, ६; ६१, ७; १४; ७१, ९; ९६, १; १०४, २; ११५, ३; ११६, १५; १२२, ७; १४; १२३, ८; १२६, २; १२८, ३; १२९, १; १४५, ४; २.

११, १२; १९, ४; ३. ५, ८; २९, ३; ३१, ७; ३२, ९; १०; ४८, १; ५५, ५; ५७, १; ५८, ८; ४. ७, ९; १०; १५, ८; १६, १२; २८, २; ३०, १८; ३१, ८; ३३, १; ४५, ७; ५१, ५; ७; ५. १, ९; ४७, ४; ५४, १०; ६. १२, ५; १९, २; ४५, ३२; ४८, २१; ६२, १; ६८, ७; ७. ४, २; ५, ७; ७, ४; १८, १३; १९, ५; ९; ३२, ५; ७५, ४; ९३, १; १०१, १; ८. ३, १०; १२, ४; ४६, २५; ७७, ८; ९६, २१; ९. १८, ६, ६१, २; १०. ६, ७; २७, १९; ३१, १०; ३९, ८; ४५, ४; ६२, ८; ९३, १५^{३}; ११०, ११; ११५, १; १२०, १; १७३, ८.

सद्यःऽअर्थे १. ६०, १.

सद्यःऽऊंतयः १०. ७८, २.

सद्यःऽऊतयः ५. ५४, १५.

सद्यःऽजुवः ८. ८१, ९.

सद्यःऽवृधं ३. ३१, १३.

सधनिऽत्वं ४. १, ९.

सऽध्रन्यः ४. ४, १४; ६. ५१, ३.

सऽध्रन्या १०. ९३, ५.

सधऽमाः ७. १८, ७.

सधऽमात् ४. २१, १.

सधऽमादः १. १२१, १५; ३. ४३, ६; ५. २०, ४^{२}; ६. ३७, १; ६९, ४; ७. ४३, ५; ७६, ४; १०. ४४, ३.

सधऽमादे १. १८७, ११^{२}; ४. २३, २; ७. ३२, १; ८. २, २८; १०. १४, १०; ८८, १७.

सधऽमादे १. ३०, १३; ३. ३५, ४; ४३, ३; ७. २२, ३; ८. २, ३; ९. ६२, ६; १०. ३५, १०; ९६, १२.

सधऽमादेषु १. ५१, ८.

सधऽमाद्यः ८. ३, १; ५४, ५; ९७, ७; ९. २३, ६.

सधऽमाद्या ८. १३, २७.

सधऽमाद्यानि ४. ३, ४.

सधऽमाद्यासः १०. १०४, ४.

सधऽवीर ६. २६, ७.

सधऽस्तुति ५. १८, ५.

सधऽस्तुतिं १. १७, ९; ४. ४४, ६; ८. १, १६.

सधस्तुती इति सधऽस्तुती ८. ३८, ४.

सधऽस्तुत्याय ८. २६, १.

सधऽस्थं १. १५४, १; ३; १६३, १३; ३. ६२, १५; ७. ३९, ४; ९७, ६; ९. १, २; १६, ४; १७, ८; २१, ३; ६५, ६; १०७, ५; १०. ३२, ४; ६१, १९.

सधऽस्था ३. २०, २; ५६, ५; ९. १०३, २.

सधऽस्थात् १. ११५, ४; ५. ३१, ९; ७. ६०, ३; ८. ११, ७.

सधऽस्थानि ३. १२, ८; २५, ५.

सधऽस्थे १. १०१, ८; १४९, ४; २. ४, २; ९, ३; ३. ६, ४; ७, ४; २३, १; ५१, ९; ५. २९, ६; ४५, ८; ५२, ७; ६४, ५; ८७, ३; ६. ५२, १५; ८. ४५, २०; ७९, ९; १०. ११, ९; १६, १०; ४०, २; ६४, ८; ६७, ९.

सधस्थे इति सधऽस्थे १०. १७, ६.

सधऽस्थेषु ९. ४८, १.

सध्रिः ८. ४३, ९.

सध्री २. १३, २.

सध्रीचीः १. १६४, ३१; ३. ३१, १६; ६. ३६, ३; १०. ४३, १; १११, १०.

सध्रीचीनः १०. ११२, ३.

सध्रीचीना १. १०८, ३; ३. ५५, १५; १०. १०६, १.

सध्रीचीनाः १. १०५, १०; १३४, २.

सध्रीचीनेन १. ३३, ११; ४. २४, ६.

सध्रेः ५. ४४, १०.

सध्र्यक् १. ५१, ७; १०८, ३; १३२, २; २. १७, ३; ३. ३१, ६; ४. ४७, २; ८. ३२, २३; ९. २९, ४.

सध्र्यचः ४. ४, १२; ५. ६०, ३.

सध्र्यचा १. १०८, ३.

सन् १. ६९, २; ७१, ४; १०; ७६, ५; ९४, ७; १००, ४; १२९, ११; १६५, ३; १७०, ३; ३. ९, २; २२, १; ३०, ५; ३२, १२; ४. १५, १; २७, १; ६. १, २; २, ६; ३२, ३; ७. १८, २; २८, ३२, १; ६८, ५; ८८, ६; ८. १६, ८; १७, १५; ३३, ९; ४३, ९; १४; ९. १९, ३; ६६, १६; ९६, १७; १०. ४, ४; २२, १५; ४२, ६; ८३, ५; ११७, २; १२३, ५.

सन् ५. १९, ५.

सनं ९. ४, १; २^{२}; ३; ९, ९^{२}.

सनःऽजाः १०. २६, ८.

सनकाः १. ३३, ४.

सनकात् ३. २९, १४; १०. ६९, १२.

सनऽजा १. ६२, ७.

सनऽजा ३. ३९, २.

सनऽजाः १०. १११, ३.

सनत् १. १००, १८^{२}; १२६, ३; ५. ६१, ५.

सनत् १. १००, ६.

सनता २. ३, ६; ३. ३, १.

सनत्ऽरयिः ९. ५२, १.

सनत्ऽवाजः ९. ६२, २३.

सनत्ऽवाजं १०. ४७, ४.

सनंतः ७. ५२, १.

सनं ८. ६८, १७.

सनयः १. १००, १३; ३. २०, ४; ३०, २१; ४. ५१, ४.

सनयं १०. ३९, ४.

सनयासु १०. ४, ५.

सनये १. ३०, १६; ३१, ८; ११६, १२; २१; १२४, ७; २. ३१, ३; ४. २०, ३; ६. २६, ८; ७. ७९, ५; ९. ९२, १; ९६, २०; १०. ३०, ११.

सनरस्य १. ९६, ८.

सनवंथ १०. ९७, ५.

सनऽवित्तः ७. ४२, २.

सनऽवित्तं १०. ११२, ६.

सनऽश्रुत ३. ५२, ४.

सनऽश्रुतः १०. २३, ३.

सनऽश्रुतं ३. ११, ४; ८. ९२, २.

सना १. १३९, ८; १७४, ८; २. २४, ५; ३. ५४, ९; ४. ३३, ३; ५. ७५, २; ८. ४५, २५.

सनाः ३. १, ६.

सनाऽजुरा ४. ३६, ३.

सनाऽजुर्वः १. १४१, ५.
सनात् १. ५१, ६; ५५, २; ६२, ८; १०; १२; १०२, ८; १६४, १३; २. १६, १; २७, १; ४. २०, ६; ५६, ६; ७. ३२, २४; ५६, ५; ८. २, ३१; ११, १०; २१, १३; २५, २; १०. ५५, ६; ७८, ८; ८७, १९; १११, १०.
सनानि १. ९५, १०; ३. १, २०.
सऽनाभयः ९. ८९, ४; १०. ७८, ४.
सऽनाभिः १. १६४, १३; १०. १३३, ५.
सऽनामाना १०. ७३, ६.
सनाऽयते १. ६२, १३.
सनाऽयुर्वः १. ६२, ११.
सनिः ८. १२, १२.
सनितरिति ८. ४६, २०.
सनिता १. २७, ९; ३६, १३; १००, ९; १०; १२९, २; १७५, ३; २. २३, १३; ४. १७, ८; ३७, ६; ५. ५०, ४; ६. ३३, २; ७. ३७, ५; ५६, २३; ८. २, ३६; १९, ९; १०^{२}; ६१, १२; ९. ९०, ३; १०. ६१, ९^{२}; ९९, ९.
सनिता १. ३०, १६.
सनितारः ४. ४१, ११.
सनितारं ५. ४२, ७.
सनितुः १. १६३, ५; ३. ३१, २; ५. १२, ३.
सनितौ १. ८, ६.
सनित्रं ९. ९७, २९.
सनित्वः ८. ८१, ८.
सनित्वऽभिः १०. ३६, ९.
सनिऽभ्यः ८. १६, ३; २४, २८; ६२, ११; १०. ३५, ४; ४०, ८.
सनिं १. १८, ६; २७, ४; २. ३४, ७; ३. १, २३; ५. २७, ४; ६. ६१, ६; ७०, ६; ९. ३२, ६.
सनिषत् १०. ७५, ९.
सनिषंत ९. ७९, १.
सनिषंत ५. १२, ४; १०. १४२, २.
सनिषामहे ३. ११, ९.
सनिष्ठया ८. ९२, १५.
सनिष्णत १. १३१, ५^{२}.

सनिष्यति ५. ३१, ११.
सनिष्यन् ३. २, ३; ७. १००, १; ९. ९०, १; १०. ९९, ३.
सनिष्यंतः ३. २, ४; १३, २.
सनिष्यंतीनां १०. ९७, ८.
सनिष्यवः १. ५६, २; १३१, २; ४. ५५, ६; ७. ९४, ६.
सनिष्यसि ४. २०, ३.
सनिष्युः ८. ६, ४४.
सनिष्युऽभिः ८. २७, ८.
सनिस्यदत् ९. ११०, ४.
सनिस्वनत् ८. ६९, ९.
सनीनां ८. ५, ३७.
सऽनीळाः १. ३४, ९; ६२, १०; ६९, ३; ७१, १; १६५, १; ७. ५६, १; १०. ३१, ६; १०१, १; १२३, ३.
सऽनीळाभिः ९. ७२, २.
सनीळे इति सऽनीळे १. ६२, ७.
सऽनीळेभिः १. १००, ५; १०. ९९, २.
सनुतः १. ९२, ११; २. २९, २; ५. ४५, ५; ६. ४७, १३; ५१, २; ८. ९७, ३; ९. ९८, ११; १०. ७७, ६; १००, ९; १०२, ३.
सनुंऽतरः ४. ३८, ४.
सनुतरिति ५. २, ४; ८७, ८.
सनुंत्यः २. ३०, ९; ६. ५, ४.
सनुंत्येन ६. ६२, १०.
सनुंत्री १. १२३, २.
सनुंत्रीः १०. ७, ४.
सनुयां १०. ११९, १.
सनुयाम १०. १०६, ११.
सनुयाम १. १००, १९; १०१, ११; १०२, ११; ७. २५, ५; १०. १४८, १.
सनुहि ८. ८१, ८.
सनेत् १. ५, ९.
सनेन २. २९, ३.
सनेम २. ११, १९; ७. ५२, १.
सनेम १. १७, ६; ७३, ५; ५. ६२, ७; ६. २०, १०; ८. ६१, ४; ९. ९८, १२; १०. ३६, ९.
सनेम १. १२२, ८; १२४, १३; १८९, ८; ६. १७, १५.

सनेमि १. ६२, ९; १६९, ३; ४. १०, ७; ७. ३८, ७; ५६, ९; ९. १०४, ६; १०५, ६.
सऽनेमि १. १६४, १४.
सनेयं १०. ९७, ४.
सनेयं ८. १९, २९.
सनेरू इति १०. १०६, ८.
सनोति ३. २५, २; ४. १७, ९; १०. ८०, ४.
सनोति ३. २५, २; ६. ६०, १.
सनोतु ६. ५४, ५.
संतः १. ११०, ४; १३८, ३; ३. ३२, १६; ४. ५, ५; १६, १९; ५. १२, ५; ६. ६६, ४; १०. ३४, ९; ६७, १०.
संतं १. ७२, २; ८४, १७; ११०, ३; १२९, १; ७; १४१, ३; १४८, ५; २. १३, १२; ३. ५, १०; ४. १, १५; ७, ६; ५. ८, ३; ४०, ७; ६. १७, ५; ८. ११, ४; ४५, १७; ७१, १३; ८०, ४; ८६, ४; ९२, ८; ९. ९, ५; १०. २७, ४; ५५, ५; ९३, ११; ११४, ५; १२४, २; ६; १७१, ४.
संतस्थाने इति संऽतस्थाने १०. ३१, ७.
संता १. २१, ४; ४. ३६, ३; ९. ६८, ५.
संति १. ८, ९; ११, ८; ३७, १४; ८५, १२; ९१, ९; १६४, ५०; १८६, १०; २. २३, ९; २८, १; ३. ६, ८; १६, २; ४. २३, ८; ३८, १; ४७, ४; ५. ३३, ४; ३५, २; ४२, ८; ५२, २; १३; ६. १, १३; १०, ५; २९, ४; ६६, ३; ६७, ५; ७. ३, ८; ३९, ४; ४८, ३; ५३, ३, ५८, २; ६०, ५; ८. १, ९; ८, २३; १०, ४; १८, २; २०, २०; २१, ६^{२}; ३१, १३; ४६, ७; ५४, ७; ९. ६१, ३०; ७८, २; १०. ४४, ७; ७८, ८; ९०, १६; १००, १२; १११, १; ११५, ४; ७.
संति १. १४५, १; ३. ३८, ५; ४. १, ७; २३, ९; ५. १२, ४; ८. १९, ८; ९. ७३, ४; ८९, ५; १०. ५४, ४; ९५, १५; १०८, ५.

संतुं ४. १०, ८.

संतु १. ५, ७; २१, ५; २६, ९; ३०, १३; ३८, १२; ३९, २; ५४, ८; ७३, १०; ९०, ६; १३१, १; १३२, २; १३५, ८; १७१, ३; ३. ५६, ८; ४. ३७, २; ५. २, १०, २८, ३; ४१, ९; ७३, १०; ६. १, १२; १५, १९; ५२, २; ७४, २; ७. १, १०; ३, १०; १२, ३; १६, ७; २२, ९; २८, १; ३५, २–४; ७; ८; १२; ५१, २; ६२, ६; १०१, ५; ८. २, ७; ३३, १५; ६०, ६; ७७, २; ८३, २; ९. ७०, ३; ७४, ६; ८५, १; १०. १८, १२; २२, १३; ३८, ३; ४४, ७; ५१, ९; ६६, ६; ८५, २३; १०३, १३; १०८, ६; ११६, ८; १२८, २.

संतौं १. १८४, १; १०. ११७, ९.

संत्यु १. १५, १२; ३६, २; ४५, ५; ९; ३. २१, ३; ५. ५१, ३; ८. १९, २६; ४४, ९; २८.

संदुदी इतिं संऽदुदी २. ३९, ७.

सन्यंसे ३. ३१, १९; ८. २४, २६; ६७, १८.

सन्वंतु १. १२२, १२.

सपत्नऽघ्नी १०. १५९, ५.

सपत्नऽहा १०. १६६, २; १७०, २; १७४, ५.

सऽपत्नाः १०. १२८, ९; १६६, २.

सऽपत्नान् १०. १७४, २.

सऽपत्नानां १०. १६६, १.

सऽपत्नीं १०. १४५, ३.

सपत्नी इतिं सपऽत्नीं ३. १, १०; ६, ४.

सऽपत्नीः १०. १५९, ६.

सपत्नीःऽइव १. १०५, ८.

सऽपत्नीं १०. १४५, १; २; ४; ५.

सपंत ५. ३, ४.

सर्पंतः १. ६७, ४; ६८, २; २. ११, १२.

सर्पंता ५. ६८, ४.

सर्पंति ९. ९७, ३७.

सर्पंते ७. ३८, ५.

सपर्य १०. ९८, ४.

सपर्यत ३. ९, ८; ५. १४, ५; २५, ४; ८. ४१, ६; १०३, ३; १०. ३७, १; ११८, ६.

सपर्यंतः १. ८३, ३; १४४, ४; १०. ५०, १.

सपर्यतः ८. ६२, ५.

सपर्यंतः ६. ४४, ५; ८. ९३, १२.

सपर्यंति १. १२, ८; ९३, २; ८. ४४, १५; ९५, ४.

सपर्यंति ८. ७, २०; ६४, ७; १०. ९३, २.

सपर्यन् १. १५३, ३; ३. ३१, १; १९; ४. १२, २; ५. ४०, ८; १०. ६९, १०; १०५, ४.

सपर्यन् १. ७०, ५.

सपर्यंतः ५. २१, ३; ८. ३१, १४.

सपर्यंता ८. २६, १३.

सपर्यंति १. ८४, १२; १०. २०, २.

सपर्यंती ८. १२, १०.

सपर्यं १०. ७, ३.

सपर्यवंः २. ६, ३; ३. ५४, २; ७. २, ४; ९४, १०.

सपर्या १०. १०६, ५.

सपर्यात् १. ९३, ८; ६. ६०, १.

सपर्यान् १. ७२, ३.

सपर्यामिं १. ५८, ७; ३. ५४, ३.

सपर्यू इतिं ३. ५०, २.

सपर्येण्यः ६. १, ६.

सपर्येम २. ६, ३.

सपामि ५. १२, २.

सऽपित्वं १. १०९, ७.

सर्पीतिऽभिः ८. १, २३.

सपेम ४. ४, ९; ५. ४३, १२; ६. १५, १०.

सप्त १. २२, १६; ३२, १२; ३५, ८; ५०, ८; ९; ५८, ७; ६२, ४; ६३, ७; ७१, ७; ७२, ६; ८; १०२, २; १०५, ९; १६४, २; $३^{४}$; ५; ११; २४; ३६; १७४, २; १९१, १२; $१४^{२}$; २. ५, २; १२, ३; १२; ३. १, ४; ६; ४, ५; ७; ७, १; ७; १०, ४; ३१, ५; ४. १, १२; १६; २, १५; ७, ५; १३, ३; १६, ३; १९, ३; २८, १; ४२, ८; ५८, ३; ५. १, ५; ४३, १; ५२, $१७^{२}$; ६. ७, ६; २०, १०; २२, २; ७४, १; ७. १८, १३; २४; ६०, ३; ६६, १५; ६७, ८; ८७, ४; ८. २४, २७; २८, $५^{२}$; ४६, २६; ५४, ४; ५९, ३; ४; ६०, १६; ६९, ७; १२; ७२, ७; १६; ९२, २०; ९६, १; २; ९. ८, ४; ९, ४; ६; १०, ३; १५, ८; ५४, २; ६२, १७; ६६, ६; ८; ७०, १; ८६, २१; २५; ३६; ९२, २; ४; १०२, २; ४; १०३, ३; ११४, $३^{२}$; १०. ५, ५; ६; ८, ४; १३, ५; १७, ११; २७, १५; ३५, १०; ४३, ३; ४९, ९; ६१, १; ६३, ७; ६४, ८; ७१, ३; ९०, $१५^{२}$; ९३, १५; ९७, १; १०४, ८; ११४, ७; १२०, ६; १२२, ३; ४; १३०, ७.

सप्तऽअंश्वः ५. ४५, ९.

सप्तऽआस्यः ४. ५०, ४.

सप्तऽआस्यं १०. ४०, ८.

सप्तऽआस्ये ४. ५१, ४.

सप्तऽआस्येभिः ९. १११, १.

सप्तऽऋषयः १०. १०९, ४.

सप्तऽऋषीन् १०. ८२, २.

सप्तऽगुं १०. ४७, ६.

सप्तऽचंक्रं १. १६४, ३; २. ४०, ३.

सप्तऽचंक्रे १. १६४, १२.

सप्तऽजामयः ९. १०, ७.

सप्तऽजिव्हाः ३. ६, २.

सप्तऽतंतुं १०. ५२, ४; १२४, १.

सप्ततिं १०. ९३, १५.

सप्ततीनां ८. १९, ३७; ४६, २६.

सप्तत्या २. १८, ५.

सप्तथं १. १६४, १५.

सप्तथंस्य १०. ९९, २.

सप्तथीं ७. ३६, ६.

सप्तऽधांतु ४. ५, ६.

सप्तऽधांतुः ६. ६१, १२; १०. ३२, ४.

सप्तऽनामा १. १६४, २.

सप्तऽपंदीं ८. ७२, १६.

सप्तऽपुंत्रं १. १६४, १.

सप्तऽवुध्नं ८. ४०, ५.
सप्तऽभिः १०. ७२, ८; ९.
सप्तऽस्यः ८. ९६, १६; १०. २५, ११.
सप्तऽमातरं १०. १०७, ४.
सप्तमातृऽभिः १. ३४, ८.
सप्तऽमानुषः ८. ३९, ८.
सप्तयः १. ४७, ८; ८५, १; ६; ८. ४६, ७; ९. २१, ४; ६५, २६; १०. १४२, २.
सप्तयुः ८. २०, २३.
सप्तऽरश्मिः २. १२, १२; १८, १; ४. ५०, ४.
सप्तऽरश्मिं १. १४६, १; ६. ४४, २४; १०. ८, ८.
सप्तऽवध्रये ५. ७८, ६; १०. ३९, ९.
सप्तऽवध्रिः ८. ७३, ९.
सप्तऽवध्रिं ५. ७८, ५.
सप्तऽशिवासु १. १४१, २.
सप्तऽशीर्षाणं ३. ५, ५; ८. ५१, ४.
सप्तऽशीर्ष्णीं १०. ६७, १.
सप्तऽसंस्थ १०. ५५, ३; ७५, १.
सप्तऽस्वसा ६. ६१, १०; ८. ४१, २.
सप्तऽहा १०. ४९, ८.
सप्तऽहोता ३. २९, १४; १०. ६४, ५.
सप्तानां ८. २८, ५; ४१, ९.
सप्तिः २. ३१, ७; ७. ४३, २; ९. ७०, १०; ९६, ९; १०३, ६; १०६, १२; १०७, ११; १०. ६, २.
सप्तिःऽइव ९. ९६, १६.
सप्तिऽभिः ८. १३, १३.
सप्तिं ३. २२, १; ८. ४३, २५; ९. २९, २; १०. ८०, १; १५६, १.
सप्तिऽइव १. ६१, ५.
सप्तिऽवन्तः १०. ६, ६.
सप्तिऽवन्ता ७. ९४, १०.
सप्ती इति ३. ३५, २; ८. ३३, १८; १०. ६०, ६.
सप्ती इवेति सप्तीऽइव ६. ५९, ३.
सप्तेः १. १६२, १.
सप्तो इति ८. २८, ५.
सप्त्यं ८. ४१, ४.
सऽप्रथः १. २२, १५; १२९, ३^{२}; १४२, ५; ६. १५, ३^{२}; १६, ३३; ६८, ९; ७. ३१, ६; ८२, १०; ८. ५, १२; १८, ३; २०, १३; ३०, ४; ४७, ७; ९. ७४, १; ८५, ८; १०. १२६, ७; १८१, १.
सप्रथःऽतमं १. १८, ९; ४५, ७; ७५, १; १०. १४०, ६.
सप्रथःऽतमे १. ९४, १३; ५. ६५, ५.
सऽप्रथाः १. १५६, १; ३. ५९, ७; ५. १३, ४; ७. ७७, २; ८. ६०, ५.
सप्सरासः १. १६८, ९.
सबःऽदुघः ९. १२, ७.
सबःऽदुघां १. १३४, ४.
सबःऽदुघाः ३. ५५, १६.
सबःऽदुघां १. २०, ३; ६. ४८, ११; ८. १, १०.
सबःऽदुघायाः १. १२१, ५.
सबःऽधुक् १०. ६९, ८.
सबःऽधुं १०. ६१, १७.
सऽबंधवः ५. ५९, ५; ८. २०, २१; ९. १४, २.
सबंधू इति सऽबंधू ३. १, १०; ५. ४७, ५; १०. १०, ९.
सबर्दुघे इति सबःऽदुघे ३. ५५, १२.
सऽबलः ८. ९३, ९.
सऽबाधः १. ६४, ८; ३. २७, ६; ५१, ४; ४. १७, १८; २३, ४; ७. ८, १; २६, २; ५३, १; ६१, ६; ९४, ५; ८. ६६, १; ७४, ६; १२; १०. २०१, १२.
सऽबाधसः ५. १०, ६.
सऽभरसः ५. ५४, १०.
सऽभराः १०. १०१, ३.
सभां ८. ४, ९; १०. ३४, ६.
सभाऽवती १. १६७, ३.
सभाऽवान् ४. २, ५.
सभाऽसहेन १०. ७१, १०.
सभासु ६. २८, ६.
सऽभृतयः ६. ६७, ७.
सभेयः २. २४, १३.
सभेयं १. ९१, २०.
सं १. ६. ३; ७; ९; ८, ३; ९, ५; ७; १०, ८; १२, ६; २०, ५; २२, २१; २३, २३^{२}; २४^{३}; २५, १७; २९, ५; ३०, ३; ४; ६; ३१, १०^{२}; १८; ३२, ६; ३३, ३; १३; ३६, ४; ७; ९; १४; २०; ३७, १३; ४२, १; ४४, ७; ४८, १६^{४}; ५३, ४; ५^{४}; ७; ५४, १; ५७, ३; ६१, ४; ५; ६२, ३; ६४, १; ८; ६८, ४; ७३, ७; ८०, १५; १६; ८१, ७; ८२, ६; ८३, ४; ८७, ६; ९१, १६; १८^{३}; ९३, ९; ९४, १; १०२, १०; १०३, १; १०५, ८; १०८, १३; ११०, १; ४; ८; १११, ३; ५; ११५, ४; ५; ११६, १७; ११७, ४; ११; १९; ११९, २; ३; ७; १२१, १५; १२३, ७; १२५, ७; १३०, ४^{२}; १३२, ५; १३३, १; ५; १३६, २; १४०, ७; ८; १४४, ३^{२}; १४५, ३; १६०, ४; ५; १६२, १८; १६३, १०; १६४, ३; ८; २९; १६५, १; ३; १६७, ३; १६८, ३; १७०, ४; ५; १७३, ६; १७९, २; १८१, ४; १८८, २; ११; १९०, २; ७; २. १, १५; ३, २; ७^{२}; ११, ८; १३, ९; १३; १४, १२; १५, ४; ६; १६, ८; १७, ४; ३१, ७; ३५, ३; ११; १२; ३८, ४; ३९, ७^{२}; ३. १, ११; १३; १५; २, १; १०; ३, ७; ५, २; ७, १; १०; ८, १०; १०, १; ९; ११, २; १६, ६; १७, १; १९, २; २१, ३; २४, २; २५, ५; २६, ३; २७, ११; १३–१५; २९, १३; १५; ३०, ८; १२; १६; १८; २१; ३१, १; १२; १५; ३२, १५; ३३, १२; ३४, ६; ३५, ८; ३६, ८; ३८, ३^{२}; ५०, ३; ५१, ४; ५४, ५; ८; २१; २२^{२}; ५५, २०; ६०, २; ३; ६२, ९; ४. ३, ११; १५; ४, ८; ८, ७; १७, ११^{३}; १८, २; ९; १९, ९; २०, ४; २३, २; २४, ४; २५, ७; २९, २; ३०, ९; ३१, ६^{२}; ३४, १; २^{२}; ११^{३}; ३५, ७; ९; ३७, ८; ३८, १०; ४२, ३; ४४, ५; ५०, ९; ५३, ७; ५६, ३; ५८, १; ५. १, ४; २, १२; ४, २^{२}; ७; ६, २^{३}; ७,

१; ३[२]; ८, १; ७; ९, २[२]; ११, २; १३, १; १६, ३; १९, ५; २१, १; २६, ३; २८, ३; ४; ३०, १०[२]; ३१, ८; ११; ३२, १०; ३४, ७; ८; ३६, ६; ३७, १; ५; ४२, ४[५]; १८; ४४, ६; ११; ४५, ८; ५१, १५; ५४, २; १२; ५८, ५; ५९, ८; ६०, ५; ६५, ६; ७३, ४; ७८, ६; ८१, ४; ८५, ४; **६.** ५, २; ७, २; ४; १५, ९; १२[२]; १९; १६, १५; १७, १०; १९, ३; ५; ९; २०, ६[२]; २३, ९; २५, ९; २६, १; ३४, १; ४; ३८, ३; ४०, २[२]; ४१, २; ३; ४६, २; ८; ४७, १४; ३१; ४८, १५[२]; ५४, १; २; ७; ५५, १; ६३, १०; ६७, १; ३; ६९, १[२]; ३[२]; ७०, ६; ७२, ५; ७३, ३; ७५, ११; **७.** १, १६; २, १; ३; ५; ३, ३; ४, २[२]; ८, १; १६, ३; २०, ४; २८, ३; ३१, ९; १२; ३३, ९; ३७, २; ४०, १; ४१, ६; ४२, ३; ४८, ४; ५५, ६; ५६, २२; ६०, ३; ६१, ६; ७३, ४; ७६, ५; ७९, २; ८१, २; ८२, २[२]; ८३, ३; ८६, २; ९३, ५; १०३, २; १०४, २; ४; १८; १९; **८.** १, २८; ३, ७; ४, १६; ६, ४; ७, २२[४]; ९, १८; १२, १६–१८; २२–२४; १३, २; २९; १८, १४; २१, १४; २३, १६; २५, ६; ३१, ९; ३२, ९; ३६, १; ४०, ३; ४२, ३; ४३, ५; ४७, १७; ४८, ५; ६; ५१, २; ५२, १०[५]; ५३, ८; ६०, १५; ६२, ११; ६६, ५; ७०, ४; १२[२]; ७२, १४; ७५, १२; ७७, ३; ७९, ८; ८१, १; ९२, १५; ९५, १; ९७, ११[२]; १२; **९.** २, ६; ५, १०; ६, ६; ७, ९; ८, ५; १४, ४; ७; १८, ५; २५, ३; ३४, ४; ६; ४५, ५; ६१, ७; ८[९]; ६३, २१; ६४, ३[२]; २३; ६६, ८; ९; ६७, ९; ६८, ४; ५; ७१, ५; ८[२]; ७२, १; ३; ५; ६; ७३, १[२]; ४; ७४, २; ७९, ३; ८२, ३; ८३, १; ८५, ५; ८६, १५; १६; ३१; ४३; ९०, ४; ९३, २[२]; ९५, ३; ९६, २; १२; १४[२]; ९७, १; ३; ३५; ४५[२]; ५५; १०१, ८; ११; १०४, २; १०५, २; १०६, ३; ११; ११०, ८; १११, २; ३; ११३, ५[२]; **१०.** ५, २; ३; ६, ६; १०, ११; १२; १३, ३; १४, ८[३]; १६, ५; ७; १२; १४; १७, १; १३; १८, ७; ८; १९, ७; २५, ४; २७, ५; ८; ९; १५; ३०, ६[२]; ३१, २; ४२, ९; ४४, ४; ४६, १०; ४८, १; ४९, ६; ५३, ८; १०; ५४, ६; ५५, २; ५; ५६, १; ४; ५९, १०; ६१, १७; ६८, २; ६९, ६; ७१, ३; ७२, २; ७९, १; २; ७; ८०, ३; ८१, ३[२]; ८२, २; ४; ८४, ४; ८५, २२; २३[३]; २७[२]; ४३; ४७[५]; ८७, ३; २४; ८८, १५; ९०, १४; ९१, १; १२; ९२, ४; १०; ९५, ७; ९; ९७, १९; २२; ९८, ११; १०१, १; ५; १०३, ६; १०७, १०; १११, २[२]; ११५, २; ११८, ४; ५, ९. १२०, २; ३; ५; १२१, १; ७; १२५, ८; १२९, ४; १३०; ४; १३२, ३; १३४, ७; १३५, ४; १४०, ३; १४३, ६; १५०, १; ४; १५१, १; १५८, ४; १५९, ६; १६८, २; १६९, ४; १७२, ४; १९१, १; २[३].

समः **९.** ६१, ८; **६.** ४८, १९; **७.** ६२, १.

संऽअकृण्वन् **१०.** ८२, ४.

संऽअंक्तं **२.** ३, १०.

संऽअंक्ताः **१०.** ६२, १.

संऽअक्षं **१०.** ८७, ११.

संऽअक्षरन् **१०**, ४३, ७.

संऽअगच्छंत **१०.** ८२, ६.

संऽअग्मंत **१०.** ९७, ६.

संऽअंक्ते **१०.** ८७, १६.

संऽअजंग्रभीत् **८.** ६, १७.

संऽअजाति **१.** १००, ११.

संऽअजासि **७.** ३२, ७.

संऽअज्यसे **९.** ८६, ४७.

संऽअंजन् **१०.** ४५, ४; ८०, १; ११०, २; १०.

संऽअंजंति **१०.** ५२, ३.

समत्ऽवां **६.** १८, २; **७.** २०, ३.

समत्ऽसु **१.** ५, ४; ६६, ३; ७०, ६; १३०, ८; १७३, ७; **२.** १२, ३; **३.** ३०, २२; **४.** २०, १; २४, ६; ३८, ४; **५.** ३३, ४; **६.** १८, ६; २५, ९; ३३, १; ४६, ३; ७५, १३; **७.** ३०, ३; ३४, ६; **८.** ११, ८; ९; १६, १०; १९, २०; २३, १२; ४०, १; ९०, १; **९.** ४, ८; ९०, ३; १११, ३; **१०.** ८०, २; १३३, १.

सऽमदः **६.** ७५, २.

सऽमदनस्य **१.** १००, ६.

सऽमदं **१०.** १२५, ६.

संऽअदहः **१०.** १६, १३.

सऽमदां **६.** ७५, १.

संऽअधंत्त **१.** १६५, ६.

समनऽगाः **७.** ९, ४.

समनगाःऽइव **१.** १२४, ८.

समनं **१.** ४८, ६; **१०.** ६९, ११; ८६, १०; १६८, २.

सऽमनसः **१.** १८६, ८; **६.** ९, ५; **७.** ४३, २; ४; ५२, ३; ९१, ३; **८.** २७, ५; **१०.** १०१, १.

सऽमनसा **१.** ९२, १६; ११३, ३; ११६, १९; **५.** ३, २; **७.** ७४, २; **८.** ३१, ५; **१०.** ९५, १२.

समना **६.** ७५, ५; **९.** ९६, ९.

समना **१.** १२४, ३; १६८, १; **२.** ११, ७; **४.** ५, ७; ४३, ७; ५१, ८[२]; ९; **६.** ४, १; **८.** ४१, २; ६६, ७; **१०.** ६९, ८; ७३, ४.

समनाऽइव **४.** ५८, ८; **६.** ७५, ४; **८.** ६२, ९.

समनाऽइव **१.** १०३, १.

संऽअनीकेषु **१०.** १०७, ११.

समने **२.** १६, ७; **६.** ७५, ३; **१०.** ५५, ५; १४३, ४.

समंनेषु ७. २, ५; ९. ९७, ४७.
संऽअंत ५. १, ११.
संऽअंता १०. ११४, १.
समंते इति संऽअंते १. १८५, ५; ७. ८०, १.
सऽमन्यवः ७. २५, १; ८. २७, १४.
सऽमन्यवः ४. १, १.
सऽमन्यवः २. ३४, ३; ५; ६; ५. ८७, ८; ८. २०, १; २१.
समन्यां ९. ९७, २.
संऽअपंश्यंत १०. ८२, ५.
समं १०. ११७, ९^{3}.
समं १. १७६, ४.
संऽअयंते ७. ८३, २.
समर्या १. ५६, ६; ७३, ६; ११३, १०; १६३, ३; १६६, ९; ७. ६६, १५; ९. ७५, ४; ८५, ५; ९७, ५६.
संऽअयोधयः १. ८०, १३.
संऽअरंणं १. १५५, २; १०. २७, ३.
संऽअरंणे १. १७०, २; ४. ४२, ५; १०. २७, ३.
संऽअरंत ७. २५, १.
संऽअराणः १. १६५, ३.
संऽअरे ६. ९, २; ४७, ६; १०. १३९, ३.
सऽमर्यः ५. ३३, १; ७. ७०, ६.
समर्यऽजित् १. १११, ५.
सऽमर्यता ५. ४४, ७.
सऽमर्यं ४. २४, ८.
समर्यऽराज्ये ९. ११०, २.
सऽमर्ये १. ६३, ६; १६७, १०; १७८, ४; ३. ८, ५; ४. ३८, ७; ५. ३, ६; ७. १९, २; २३, १; ९. १, ७; ८५, २; ९७, २७; १०. २७, २४.
संऽअवर्तयत् ८. ६, ५.
संऽअविव्यक् ७. ६३, १.
संऽअवृक्त ७. ३, ४.
संऽअशीत १. ५७, २.
संऽअस्थिरथाः १०. ११३, ३.
संऽअस्थिरन् १०. ११८, २.
समस्मात् ५. २४, ३.
समस्मिन् ८. २१, ८.

समस्मै ६. ५१, ६.
समस्य ६. २७, ३; ४२, ४; ५३, ८; ८. ७५, ९; ९. २९, ५; ६१, ३०; १०. २९, ४; ५४, ३.
संऽअस्वरन् ९. ७३, ५; १०. ९६, २.
समह १. १२०, ११; ५. ५३, १५; ७. ८९, ३; ८. ७०, १४.
समा ८. १, ६; १०. ११७, ९.
समाः १०. १२४, ४.
समाः ५. ८३, ७.
संऽआकृणोषि १०. २५, ६.
संऽआकृतं १०. ८४, ७.
संऽआचक्रे ३. ३६, ५.
संऽआंजन् १०. ८८, ४.
समानः १. ११३, ३; २. १३, २; ३. ५५, ४; ४. ३०, २२; ६. ५९, २; ७. २६, ३; ७२, २; ८. ७३, १२; १०. १९१, ३.
संऽआनजे १. १८८, ९.
समानतः ४. ५१, ८.
समानऽदक्षाः ७. २६, २.
समानबंधू इति समानऽबंधू १. ११३, २.
समानं १. २५, ६; ९२, १०; १२७, ८; १३०, ५; १३१, २; १४४, ३; १४६, ३; १६४, २०; ५१; २. १२, ८; ३५, ३; ३. २, १२; ३३, ३; ६१, ३; ४. ५, ७; ६. ६६, १; ७. ३३, १३; ५७, ३; ६३, २; ३; ८६, ३; १०३, ६; ८. २०, ११; ४५, २८; ७३, १२; ९९, ८; १०. ५, २; १७, ११; २७, १६; ४१, १; ८९, ३; ९१, ६; ८; १२३, २; ३; १९१, ३^{2}; ४.
समानऽयोजनः १. ३०, १८.
समानऽवर्चसा १. ६, ७.
समानस्मात् ५. ८७, ४.
समाना १०. १९१, ४.
समानाः ३. ५८, ६.
समानात् २. १७, ७.
समानान् ६. ४, १.
समानानां १०. १६६, १.
समानां १०. ८५, ५.
समानी १०. १९१, ३; ४.

समानीः ४. ५१, ९.
समाने १. ३४, ३; १४४, ४; १८६, ४; ६. ५९, ५; ७. ६७, ८; ७६, ५; ८. २, ८; ९. ८९, ५; १०. १०, ७; ३१, ६.
समानेन १. ९२, ३; ३. ५४, ६; १०. १९१, ३.
समानेभिः १. १६५, ७.
समानैः १. ६९, ४.
समान्या १. १३२, ४; १६५, १; ३. ५४, ७; ५. ४८, २; ८. ८३, ८.
समां ४. ५७, ७.
संऽआयन् १०. ३१, ५.
संऽआयमुः १०. ९४, ६.
संऽआरत १. १४५, ४.
समाराणे इति संऽआराणे ३. ३३, २.
संऽआवर्तं १. ११२, १८.
संऽआववर्ति २. ३८, ६.
संऽआशिरां १. ३०, २.
संऽआसते ३. ९, ७; ७. १, ४.
संऽइंगयति ५. ७८, ७.
संऽइत ५. ६, ४; १०. ५२, २; ८०, २.
संऽईताः ७. ८३, ७.
संऽईतिः १. ९५, ८; १०. ११, ८; १९१, ३.
संऽईतिं १०. १६६, ४.
संऽईतीः ९. ९२, ६.
समितौऽइव १०. ९७, ६.
समित्ऽभिः ३. १, २; ६. १६, ११; ८. ४३, १२.
समित्ऽसमित् ३. ४, १.
संऽइथा ९. ९४, ४.
संऽइथानि १. ५५, ५.
संऽइथे २. २४, १३; ३. १, १२; ५४, ४; ४. ३८, ९; ५८, ११; ६. २५, ६; ७. १००, ६; ९. ७६, ५; १०. २५, ९.
संऽइथेषु १. ७३, ५; ४. २०, ८; ४१, २; ७. ८३, ९; १०. ४८, ९; ६४, ६.
समिद्धऽअग्निः ५. ३७, २; १०. ६३, ७.
संऽइद्धः १. ९४, १४; १४२, १; १८८, १; २. ३, १; १०, १; ३. ५, १; ४;

१८, ५; ५. ३, १; २१, ४; २८, १; ५; ५८, ३; ६. १६, ३४; ७. १२, १; १७, १; ७८, २; ९३, ७; ८. ५८, २; १०३, ९; ९. ५, १; १०. ३, १; ७०, ७; ८७, १; २; ८८, ७; ११०, १; १५०, १.

संऽइद्धं ३. ९, ७; ६. १५, ७; ७. २, ३; ४४, १.

संऽइद्धस्य ३. ८, २; ५. १, २; २८, ४.

संऽइद्धाः १०. ३५, १३.

संऽइद्धे २. ९, ३; ३. ५५, ३; ४. २५, १; ३९, ३; ६. ४०, ३.

संऽइद्धेषु १. १०८, ४.

संऽइधः १. १६४, २५; ३. २, ९; ४. ५८, ८; १०. ५१, २; ९०, १५.

संऽइधं १. ९४, ३; २. ६, १; ३७, ६; ५. ४, ४; ७. २, १; १०. ६९, १०.

संऽइधा १. ९५, ११; ९६, ९; ३. ५, ९; १०; १०, ३; ४. ४, १५; ५. १, १; ६. १, ९; १०; २, ५; ५, ५; १५, ६; ७; १९; ७. १४, १; २; ७२, ४; ८. १९, ५; १४; ४४, १; १०. १२, २; ८७, ८; ९१, ११; १२२, ३.

संऽइधान् ४. ४, ४; ६, ११; ८. ६०, ५; १०. १५०, २.

संऽइधानः १. १४३, ७; २. २, ६; ३. ४, ११; ५. ८, ४; १४, १; २६, ६; ६. ४८, ७; ७. ९, ६; ६७, २; ८. २५, १९; ४४, ९; १०. २, ७.

संऽइधानं २. २, १; ५. ८, ६; ७. ९, ४; १०. ३५, ३.

संऽइधानस्य १. १४३, २; ४. ५, १५; ८. ४४, ४; १०. ३६, १२.

संऽइधाने १. १२४, १; २. १६, १; ३. ३०, २; ४. ६, ४.

संऽइधे १. ११३, ९; ७. ७७, १.

संऽइध्यते ४. १५, ४.

संऽइध्यमानः ३. १७, १; २७, ४; ५. २८, २.

संऽइध्यसे ८. ४३, १४.

संऽइनक्षंतः ९. ७३, ९.

संऽइषः ८. ५०, २.

संऽईके ३. ३०, ११; ४. २४, ३; ७. २१, ९; ८. ३, ५; १०. ४२, ४.

समीची इति संऽईची १. ६९, १; ९६, ५; २. ३, ६; २७, १५; ३. १, ७; ३०, ११; ५५, १२; २०; ८. ६, १७; १०. २४, ४; ८८, १६.

संऽईचीः ३. २९, १३; ३१, १३; ४. १७, ९; १०. ६१, २५.

संऽईचीनाः ९. ३९, ६; ७४, ४.

संऽईचीनासः ८. ३, ७; १२, ३२; ९. १०, ७.

समीचीने इति संऽईचीने ९. ७४, २; ९०, ४; १०२, ७; १०. ४४, ८.

संऽईच्योः १०. २४, ५.

संऽईजमानः ६. २९, ५.

संऽईधे ३. ५, १०; १०. ६९, ३; ४; ९८, ८.

संऽईयतुः १०. ११३, ७.

संऽउक्षितं ३. ६०, ५; ८. ४, १२.

संऽउक्षितानां ५. ५६, ५.

समुद्रऽअर्थाः ७. ४९, २.

समुद्रः १. ३०, ३; ११०, १; ५. ४७, ३; ७८, ८; ६. ५०, १४; ६९, ६; ७. ३५, १३; ८. ४१, ८; ९. २, ५; ६४, ८; ८६, २९; ९७, ४०; १०१, ६; १०९, ४; १०. ५, १; ६६, ११; १४९, २; १९०, १.

समुद्रःऽइव १. ८, ७; ८. ३, ४; १२, ५.

समुद्रऽज्येष्ठाः ७. ४९, १.

समुद्रतः ५. ५५, ५.

समुद्रं १. १९, ७; ८; ३२, २; ५२, ४; ५६, २; ७१, ७; ११७, १५; १३०, ५; १७४, ९; १९०, ७; २. १९, ३; ३. ३३, २; ३६, ६; ४६, ४; ४. ५५, ६; ५. ४४, ९; ८५, ६; ६. १७, १२; ३०, ४; ३६, ३; ७. ८८, ३; ८. ३, १०; ६, १३; २९; १२, २; ९. २९, ३; ६१, १५; ६३, २३; ६४, १६; १७; २७; ६६, १२; ७३, ३; ८४, ४; ८६, ८; ८८, ६; ९६, १९; १०७, ९; १५; २३; १०. ३०, ३; ५८, ५; ९८, ५; ११४, ४; १२१, ४; १२३, ८; १४९, १.

समुद्रंऽइव ८. ६, ३५; ९२, २२; ९. १०८, १६.

समुद्रंऽईखयु ९. ३५, २.

समुद्रऽवाससं ८. १०२, ४.

समुद्रऽव्यचसं १. ११, १.

समुद्रस्य १. ११६, ४; १६७, २; ८. ३४, १३; ९७, ५; ९. १२, ६; १०७, १४; १०. ८९, ११; १४२, ७; ८.

समुद्रस्यऽइव ७. ३३, ८.

समुद्रा ५. ७३, ८.

समुद्राः १. १६४, ४२.

समुद्राणि ६. ७२, ३.

समुद्रात् १. ४७, ६; ११७, १४; ११८, ६; १६३, १; ४. २१, ३; ४३, ५; ५८, १; ५; ६. ६२, ६; ७. ६, ७; ५५, ७; ९५, २; ९. ९७, ४४; १०. ९८, १२; १२३, २; १९०, २.

समुद्रान् ७. ७०, २; ९. ३३, ६.

समुद्रायऽइव ८. ६, ४; ४४, २५.

समुद्रासः ९. ८०, १.

समुद्रियः १. २५, ७; ५५, २; ९. १०७, १६; १०. ६५, १३.

समुद्रिया ७. ८७, १.

समुद्रियाः ८. ७६, ३; ९. ६२, २६; ७८, ३.

समुद्रियाणि ४. १६, ७.

समुद्रे १. ३०, १८; ४८, ३; ९५, ३; ११६, ५; १५९, ४; १६३, ४; १७३, ८; ४. ५८, ११; ६. १९, ५; ५८, ३; ७. ६८, ७; ६९, ६; ८. ५, २२; १०, १; १२, १७; १३, १५; १६, २; ६५, २; १००, ९; ९. ६४, १९; ८५, १०; ९५, ४; १०७, २१; १०. ४५, ३; ७२, ७; ९८, ६; १२५, ७; १४३, ५; १७७, १.

समुद्रेण ३. ३६, ७.

समुद्रेषु ८. २०, २५.

समुद्रैः १. १६१, १४; २. १६, ३; ६. ५०, १३.
समुद्रौ १०. १३६, ५.
संऽउद्ध्यं ५. २, १.
संऽऊळ्हं १. २२, १७.
संऽऊहसि १. १३१, ३.
संऽकृतः ४. १३, ५.
संऽकृता १. ३१, ६; ९. ७१, ८.
संऽकृतिः ४. १६, १७; ७. ६०, १०.
संऽकृतिं १. ३२, ६.
संस्कृते इति संऽकृते ३. ३८, ३.
संऽकृतेः ८. १०१, ४.
संऽकृतेषु १०. १०३, ११.
संऽकृतौ १. १२७, ३; ५. ७, २; ३४, ६.
संऽऋधः ६. २, १०.
समृधाऽइव ७. १०३, ५.
समे ८. ३९, १.
संऽएतं १०. ८५, ३३.
संऽएतिं ७. १, १४.
संऽएद्धारं ६. ४८, ८; ७. १, १५.
संऽएरिरे १०. ४०, १०.
संऽओकसः १. ६४, १०.
संऽओकसा १. १४४, ४; १५९, ४; ८. ९, १२; १०. ६५, २; ८.
संऽओकाः १. १००, १; ६. १८, ७.
संऽओहं ४. १७, १३.
संऽओहे १. ८, ६.
समौ १०. ११७, ९.
संऽकल्पः १०. १६४, ५.
संऽक्रन्दनः १०. १०३, १.
संऽक्रन्दनेन १०. १०३, २.
संऽक्रोशमानाः ४. १८, ६.
संऽगता ८. ७८, ८.
संऽगतानि १. ३६, ५.
संऽगतासः ७. ७६, ५.
संऽगतिं ४. ४४, १.
संऽगत्य १०. ९७, २१.
संऽगत्यां १०. १४१, ४.
संऽगथे १. ९१, १६; २. ३८, १०; ८. ६, २८.
संऽगमनः १. ९६, ६.
संऽगमनं १०. १४, १.
संऽगमनी १०. १२५, ३.
संऽगमामहै ८. ९१, ४.
संऽगमे १. १०२, ३; १०. ३८, ३; १०७, ४; १२३, १.
संऽगमेषु १०. १३१, ३.
संऽगवे ५. ७६, ३.
संऽगिरः १०. ८९, ९.
संऽगिरं ९. ८६, १६.
संऽगृभीता १. १००, ९.
संऽगृभीताः ७. १०४, ८.
संऽगृभ्णाः ३. ३०, ५.
संऽगृभ्य १. ५३, ३; ३. ५४, १५; १०. ४६, ६.
संऽगे ४. २०, १; १०. १३३, १.
संऽग्रथितं १०. ६१, १३.
संऽचक्रानः ५. ३०, ७.
संऽचक्षाणः ६. ५८, २.
संऽचक्षि ६. १४, ४.
संऽचक्षे १. १२७, ११; ७. १८, २०.
संऽचक्ष्यं १. १६५, १२.
संऽचरणीः ६. २४, ४.
संऽचरणे १. ५६, २; ४. ५५, ६.
संऽचरतं १०. १७, ११.
संऽचरति ८. ४८, १; १०. ४, २; १२, ८.
संचरती इति संऽचरती ३. ३३, ३.
संऽचरेण्य १. १७०, १.
संऽचिकित्वान् ४. ७, ८.
संऽचृतं ९. ८४, २.
संऽजग्मानः १. ६, ७; ९. ६४, ३०; १०. ६१, ७.
संऽजग्मानासु १. ७४, २.
संऽजनयति ५. ७, २.
संऽजयन् ९. २९, ४.
संऽजया १०. १५९, ३.
संऽजर्भुराणः ५. ४४, ५.
संऽजानानाः १. ७२, ५; १०. १९१, २.
संऽजिगीवान् ३. १५, ४.
संऽजितः ५. ४२, ५.
संऽजितं ३. ३०, २२.
संऽजिहानं ७. ३३, १०.
संऽजूर्वसि ८. ६०, ७.
संऽज्ञानं १०. १९, ४.
संऽतनिः ५. ७३, ७; ९. ६९, २.
संऽतनिं ९. ९७, १४.
संऽतरं ८. ३३, १९.
संऽतरुत्रं ३. १, १९.
संऽतरेयुः ३. ३३, ११.
संऽतवीत्वत् ४. ४०, ४.
संऽतस्थानाः १०. ४२, ४.
संऽददस्वान् २. २, ६.
संऽददिः ९. ९९, ७.
संऽदधुः १. १०१, ६; ३. ३, ३; २०, ३; १०. १००, ४.
संऽदहतः ९. ७३, ५.
संऽदानं १. १६२, ८; १६.
संऽदायि १. १३९, १.
संऽदितं १. २५, ३.
संऽदिहः १. ५१, ९.
संऽदृक् १. ६६, १; ४. १, ६; ६, ६; १०. ८२, २.
संऽदृशं २. १३, १०; ३३, १; ३. ५, २; १०. ६९, १.
संऽदृशे ६. १६, ८; ७. ८८, २.
संऽदृशि २. १, १२; ५. ७४, ६; ८७, ६; १०. ३७, ६; ५९, ५.
संऽदृशौ २. १३, ५; ३. ३८, १.
संऽदृष्टिः २. ४, ४; ४. १०, ५; ६. १६, २५.
संऽदृष्टौ १. १४४, ७; ६. १, ४.
संऽधाता ८. १, १२.
संऽधिं ८. १, १२.
संऽनद्धः १. १६४, ३७; ६. ४७, २६.
संऽनद्धा ६. ७५, ११.
संऽनममानः १०. ८७, ४.
संऽनयः २. २४, ९.
संऽनयानि १०. २७, २.
संऽनयामसि ८. ४७, १७.
संऽनवामहे ८. ६९, ५.
संऽनशे ८. ३, १०; ५५, ५.
संऽनसंत ९. ९२, ५.
संऽनसामहे १०. ६४, १३.
संऽपतंति ६. ७५, १७.
संऽपश्यन् १०. २५, ६; ११७, ८; १३९, १.
संऽपश्यमानाः ३. ३१, १०.

संऽपारणं ३. ४५, ४.
संऽपिणक् ४. ३०, १३.
संऽपिंपंति १०. ८५, ३.
संऽपिर्वते १०. १३५, १.
संऽपिष्टात् ४. ३०, १०.
संऽपृंक्ताः ८. ४, ८; १०. ३४, ७.
संऽपृक्के ७. १०३, ४.
संऽपृचंः २. ३५, ६.
संऽपृच्छे ८. १०१, ४.
संऽपृच्छे १०. ६९, ९.
संऽपृंचानः १. ९५, ८.
संऽप्रश्नं १०. ८२, ३.
संऽब्राधात् २. १६, ८.
संऽभरः ४. १७, ११.
संऽभरणं ७. २५, २.
संऽभरंति १. १६२, ६.
संऽभुजं २. १, ४.
संभृतऽअश्वः ८. ३४, १२.
संऽभृतः ८. ९३, ९.
संभृतक्रतो इति संभृतऽक्रतो १. ५२, ८.
संऽभृतं ३. ३०, १४; ३५, २; ३९, ६; ८. ४०, ६; ९. ६७, ३१; ३२; १०. ९०, ८.
संऽभृतस्य ८. ७८, १०.
संऽभृता २. १६, २; ६. ५७, ३; ७. ७३, ४.
संऽभृतैः ८. ३४, १२.
संऽमातरा १०. ११७, ९.
संऽमार्य १. ६७, ५.
संऽमिमिक्षथुः ८. १०, २.
संऽमिश्लः १. ७, २; ८. ३३, ४; ६१, १८; ९. ६१, २१; १०. ६, ४.
संऽमिश्लाः १. १६६, ११; २. ३६, २; ३. २६, ४; ७. ५६, ६.
संऽमिश्लासः १. ६४, १०.
संऽमील्य १. १६१, १२.
सम्यक् ४. ५८, ६; ५. ९, ५; ६६, २; ७०, २; ९. ७३, २.
संऽयजंते १०. ७१, ८.
सम्यंचः ९. ७३,२.
सम्यंचं ५. ७, १.
सम्यंचा १. १७९, ३; ८. २१, ६.
संऽयतः २. २, २; ५. ३४, ९; ८. २३, १०; १००, ९; ९. ७२, ६; ८६, १५; ४७.
संऽयुतः ९. ६९, ३.
संऽयतं ६. २२, १०; ७. १०२, ३; ९. ६२, ३; ६५, ३; ८६, १८.
संऽयता १. १५१, ८; ६. १६, २१.
संऽयंति ५. ९, ५.
संऽयुजे ८. ४१, ६.
संऽयोपयंतः १०. १६५, ५.
संऽरभ्य १०. ९४, ४.
संऽरराणः ८. ३२, ८; १०. १५, ८.
संरराणे इति संऽरराणे ६. ७०, ६.
संऽराजः ३. ५४, १०; ७. ६, १; ३८, ४; १०. ६३, ५.
संऽराजः ८. २७, २२.
संऽराजंतं १. २७, १.
संऽराजं ३. १०, १; ६. ७, १; ८. १६, १; १९, ३२; १०. १३४, १.
संऽराजा १. १३६, १; २. ४१, ६; ५. ६८, २; ८. २३, ३०; २५, ४; ७; २९, ९; १०. ६५, ५.
संऽराजा ५. ६३, ५.
संऽराजे ५. ८५, १; ६. ६८, ९.
संऽराजोः १. १७, १.
संऽराजौ ५. ६३, २; ३.
संऽराज्ञी १०. ८५, ४६[४].
संऽराट् २. २८, ६.
संऽराट् १. १००, १; १८८, ५; ३. ५५, ७; ५६, ५; ४. १९, २; २१, २; १०; ६. २७, ८; ७. ५८, ४; ८२, २; ८. ४२, १.
संऽराट् ८. ४६, २०; १०. ११६, ७.
संऽवतः १. १९१, १५; ५. १५, ३; ८. ७५, १५.
संऽवत्सं ४. ३३, ४[३].
संऽवननं १०. ९३, १२.
संऽवनना ८. १, २.
संऽवरणस्य ५. ३३, १०; १०. ७७, ६.
संऽवरणात् ७. ३, २.
संऽवरणानि ९. १०७, ९.
संऽवरणेषु ४. २१, ६.
संऽवर्गं ८. ७५, १२; १०. ४३, ५.
संऽवर्तयंतः ५. ४८, ३.
संऽवर्ते ८. ५४, २.
संऽववृत्वत् ५. ३१, ३.
संऽवसनेषु ९. ८६, १७.
संऽवसानं ९. २६, ४.
संऽवसाना: ४. ६, ८.
संऽवसुः ८. ३९, ७.
संऽवादाय ८. १०१, ४.
संऽवित् ८. ५८, १.
संऽविदे १०. १०, १४.
संऽविदानः ७. ४४, ४; ८. ४८, १३; १०. १४, ४; १६२, १; १६९, ४.
संऽविदाना: १०. ३०, १३; ९७, १४.
संऽविदानासः १०. ३०, १४.
संऽविंदते १०. १४५, १.
संऽविव्यानः १. १३०, ४; ५. २९, ४.
संऽवृक् २. १२, ३.
संऽवृतः ८. १७, ७.
संऽवेशने १०. ५६, १.
संऽवेविपः ८. ७५, ११.
संऽशाय १०. १८०, २.
संऽशिशानः ९. ९०, १.
संऽशिशाना: १०. ८४, १.
संऽसत् ४. १; ८.
संऽसदः ८. ९२, २०.
संऽसदं ८. १४, १५.
संऽसदा ७. ५४, ३.
संऽसदि १. ९४, १; ७. ४, ३.
संऽसं १०. १९१, १.
संऽसहस्रं ७. ८, ६.
संऽसुदे ८. १७, ६.
संऽसृजानि १०. २७, १०.
संऽसृजि १०. ८४, ६.
संऽसृष्टं १०. ८४, ७.
संऽस्तिरः १. १४०, ७.
संऽस्थे १. ५, ४; ५. ३, ८; ८. २१, ११; २७, १५; ३२, ११.
संऽस्मयमामा १. १२३, १०.
संऽस्रवाः ९. ११३, ५.
संऽस्रष्टा १०. १०२, ३.
संऽहतः ३. १, ७.
संऽहाय २. ३८, ४.
संऽहितं १. १६८, ६; ८. ६७, २१.

संऽहिता ८. ९६, २.
संऽहोत्रं १०. ८६, १०.
सयावंऽभिः १. ४४, १३; १०. २२, ११; ११३, २.
सऽयावंरी ७. ३१, ८.
सऽयावंरीः १. ८४, १०.
सऽयावानं ५. ३५, ७.
सऽयुक् १०. १६८, २.
सऽयुग्वा १०. १३०, ४.
सऽयुजः ३. ३०, ११.
सऽयुजं १०. १२४, ९.
सऽयुजा १. १६४, २०.
सऽयोनिः १. १६४, ३०; ३८.
सयोनी इति सऽयोनी १. १५९, ४.
सऽयोनीः ३. १, ६; १०. ३०, १०.
सरं ९. ४१, ६.
सरंऽअपसः २. १३, १२.
सरंः ७. १०३, ७; ८. १, २३; ४५, २४; ४९, ३.
सरजंतं १०. ११५, ३.
सरट्ऽभ्यः १. ११२, २१.
सरण्यन् ३. १, १९.
सरण्यान् ४. २१, ६.
सरण्युः १०. ६१, २३; २४.
सरण्युऽभिः १. ६२, ४; ३. ३२, ५.
सरण्यूः १०. १७, २.
सरंत् ९. १०१, १४; १०. ६१, ८; २३.
सरत् ४. ३०, १०.
सऽरथं १. ७१, ६; १०८, १; ३. ४, ११; ६, ९; ६०, ४; ४. १६, ११; ४७, ३; ५. ११, २; २९, ९; ६. २०, ५; ७. ११, १; ९१, ५; ८. ९, १२; ९. ८७, ९; ९७, ६; १०३, ५; १०. १५, १०; १७, ८; ७५, ६; ८४, १; १६८, २.
सऽरथा ५. ४३, ८; १०. १०६, ११.
सरन् ४. १७, ३.
सरमा १. ६२, ३; ७२, ८; ३. ३१, ६; ४. १६, ८; ५. ४५, ७; ८; १०. १०८, १..
सरमे १०. १०८, ३; ५; ७; ९.
सरयंते ४. १७, २.
सरयुः ५. ५३, ९; १०. ६४, ९.
सरयोः ४. ३०, १८.
सऽरश्मिः १. १३५, ३.
सरंसः ८. १, ३३.
सरसि ९. ९७, ५२.
सरसी इति ७. १०३, २.
सरस्वः ७. ९६, ५.
सरंस्वतः ७. ९६, ६.
सरंस्वति १. १६४, ४९; १८८, ८; २. ३०, ८; ४१, १६; ६. ६१, ३; १४; १०. १७, ८.
सरस्वति २. ४१, १७; १८; ६. ६१, १; ५; ६; ७. ९५, ५; ६; १०. ७५, ५; १८४, २.
सरंस्वती १. ३, १०–१२; १३, ९; ८९, ३; १४२, ९; २. १, ११; ३, ८; ३२, ८; ३. ४, ८; ५४, १३; ५. ४२, १२; ४३, ११; ४६, २; ६. ४९, ७; ५०, १२; ५२, ६; ६१, ४; ७; १०; ११; १३; ७. ३५, ११; ३६, ६; ३९, ५; ४०, ३; ९५, १; २; ४; ९६, ३; ८. २१, १७; ५४, ४; ९. ५, ८; ६७, ३२; ८१, ४; १०. १७, ७; ३०, १२; ६४, ९; ६५, १; १३; ११०, ८; १३१, ५.
सरंस्वतीं ६. ६१, २; ७. ९, ५; ९६, १; ८. २१, १८; १०. १७, ७[३]; ९; १४१, ५.
सरंस्वतीऽवतोः ८. ३८, १०.
सरंस्वत्यां ३. २३, ४.
सरंस्वंतं १. १६४, ५२; ७. ९६, ४.
सरंस्वान् १०. ६६, ५.
सरांसि ५. २९, ७; ८; ६. १७, ११; ८. ७, १०; ७७, ४; ९. ५४, २.
सऽरातयः ८. २७, १४; १७.
सरितः ४. ५८, ६; ७. ७०, २.
सरिष्यन् २. ११, ७; ४. ३८, ६.
सरीं १. १३८, ३[२].
सरीमणि ३. २९, ११.
सरीसृपं १०. १६२, ३.
सऽरूपा ४. १६, १०.
सऽरूपाः १०. १६९, २.
सऽरूपेण १०. ५५, ३.
सऽरूपैः ८. ३४, १२.
सर्गाः १. १९०, २; २. ३०, १; ३. २९, ११; ७. ८७, १; ९. १६, १; ८७, ७.
सर्गंऽतक्तः ३. ३३, ४; ११.
सर्गंऽप्रतक्तः १. ६५, ३.
सर्गे ७. १८, ११; १०. ८९, २.
सर्गंऽइव ५. ५६, ५.
सर्गाः १. १५२, १; ४. २३, ६; ५१, ८; ५२, ५; ९. २२, १; ६४, ७; ६६, १०; ९७, ३०.
सर्गान्ऽइव ८. ३५, २०.
सर्गासः ९. ६९, ६; १०. २५, ४.
सर्गे ६. ४६, १३.
सर्गेण ६. ३२, ५.
सर्गेषु ४. ३, १२.
सर्गैः १. १६९, ७.
सर्जति १०. १४६, ३.
सर्जि ९. ६९, १; ९२, १.
सर्तवे १. ३२, १२; ११६, १५; १३०, ५; २. १२, १२.
सर्तवै १. ५५, ६; ५७, ६; ३. ३२, ६; ५. २९, २.
सर्प १०. १८, १०.
सर्पः १०. १६, ६.
सर्पत् १०. ७९, ३; ९९, १२.
सर्पत १०. १४, ९.
सर्पति ९. ८६, ४४.
सर्पतु ८. १७, ७.
सर्पिः ९. ६७, ३२.
सर्पिःऽअन्नः १०. २७, १८.
सर्पिःऽआसुतिः २. ७, ६; १०. ६९, २.
सर्पिःऽआसुतिं ८. ७४, २.
सर्पिःऽआसुते ५. २१, २.
सर्पिःऽआसुते ५. ७, ९.
सर्पिरासुती इति सर्पिःऽआसुती ८. २९, ९.
सर्पिषः १. १२७, १; ५. ६, ९.
सर्पिषा १०. १८, ७.
सर्मीय १. ८०, ५.
सर्वंऽअंग १०. १६१, ५.
सर्वैः १. ४१, २; ७. ४१, ५; १०. ५१, ९; ६१, १९; १४१, ४.

सर्वैऽगणं १. ११६, ८; ५. ५१, १२.
सु॒र्वत॑ः २. ४३, २; ५. ७८, ७.
सु॒र्वैऽतातये १. १०६, २; ६. ५६, ६^{२}; ९. ९६, ४.
सु॒र्वैऽताता १. ९४, १५; ३. ५४, १९; ४. २६, ३; ५. ६९, ३; ६. १५, १८; ७. १८, १९; ५७, ७; १०. ७४, ३.
सु॒र्वताताऽइव ६. १२, २.
सु॒र्वैऽतातिं ३. ५४, ११; १०. ३६, १४; १००, १.
सु॒र्वै॒ऽधाः ९. १८, १.
सु॒र्वै॒ऽधात॑मः ८. ३१, ११.
सु॒र्वै॒ऽधात॑मं ५. ८२, १.
सर्वै १. २९, ७; ८३, ४; १३३, ५; २. २७, ३; ३. १४, ७; ७. १०३, ५; ८. ४७, १५; १७; ५८, २^{२}; ९३, ४; १०२, २१; ९. ६७, ३१; १०. ९०, २; ९७, २०; १०७, ८; १२९, ३; १६१, ५^{२}.
सर्वैया १. ३९, ५; ५. २६, ९; ८. २८, ३.
सु॒र्वै॒ऽर॒था ५. ३५, ५; १०. १६०, १.
सर्वैऽवीरः ३. ६२, ३; ९. ९०, ३; १०. १७, ५.
सर्वैऽवीरं २. ३०, ११; ४. ३५, ६; ५०, १०; ६. २३, ४; १०. १५, ११; ७६, ४.
सर्वैऽवीरया १. १११, २.
सर्वैऽवीराः १. ५१, १५; १०५, १९; ११३, १८.
सु॒र्वै॒ऽशा॒सैः ५. ४४, ४.
सर्वैऽसेनः १. ३३, ३; ५. ३०, ३.
सर्वैऽसेना ६. ६८, २.
सर्वैस्मात् १०. ९७, १६; १६३, ५.
सर्वैस्य १०. १३७, ६.
सु॒र्वै॒ऽहुतः १०. ९०, ८.
सु॒र्वै॒ऽहु॒दा १०. १६०, ३.
सर्वौ १. १६२, ८; ९; १४; १७; ५. ८५, ८; ८. ९१, ६; १०. १४, १६; १५५, २.
सर्वौः १. १८८, ८; १९१, ८; ६. ७५, २; ५; ७. २६, ३; ५०, ४; ५५, ८; १०. १७, ५; ९७, ७; १४; २१; १७३, १.
सर्वा॑न् १. १९१, ८; ७. ३३, ७; ८. ५७, ३; ९३, ६.
सर्वा॑भ्यः २. ४१, १२.
सर्वा॑सां १. १२७, ८; १९१, १३.
सर्वे॑ १. १९१, ३; ७; ६. ७५, १९; ७. ५५, ५; १०. ७१, १०; १२८, २; १५५, ४; १६६, २.
सु॒र्सृ॒ते २. २५, १.
सु॒स्रा॒ते इति॑ ३. ७, १.
सु॒स्रे॒ ६. १८, ७.
सऽलक्ष्मा १०. १०, २.
सु॒ल॒लू॒कं ३. ३०, १७.
सु॒लि॒लः १०. १०९, १.
सु॒लि॒लं १०. १२९, ३.
सु॒लि॒लस्यं ७. ४९, १.
सु॒लि॒लानि॑ २. ३, २१.
सु॒लि॒ले १०. ७२, ६.
सवनं १. १६, ५; ८; २१, ४; ३. ३२, १; ५; ४३, ४; ४. ३४, ४; ३५, ४; ६; ७; ९; ५. ४४, ९; ८. ५०, ३; ५७, १; २; ६४, ८; १०. ७६, २; ३; ९६, १३; १६०, २.
सवनस्य ३. ५२, ५; ४. ३६, २; ८. ३७, १; १०. १७९, ३.
सवना १. ४, २; ४७, ८; ५७, २; १७३, ८; ३. १, २०; ३०, २; ३६, ८; ४. २९, १; ६. २३, ४; ४७, १४; ७. २२, ६; ७; ६९, ६; ८. २६, २०; ३३, १५; ३५, ४; ३८, ५; ४६, ९; ५९, १; ६६, १२; १०. ४०, ३; ४१, १; ५०, ५; ६; ८९, १६; १११, ५; ११२, ७.
सवनानि १. १३१, १; २. ३४, ६; ४. ४५, ४; ७. ३२, ६; ९७, १; ८. ३३, १४; ९०, १; ९. ८०, १; १०. ४१, ३; ९६, ६.
सवनाय ६. ७१, १.
सवने १. १६१, ८; २. १८, ७; ३. २८, ४; ५; ३२, ३; ५२, ६; ६०, ६; ४. १६, २; १५; ३३, ११; ३५, १; ५. ४०, ४; ६. ४७, ६; ७. २३, ५; २९, २; ५९, ७; ९२, ५; ८. ८, ३; १०. ४४, ९.
सवनेषु १. ९, ३; ५१, १३; ६१, ७; १३१, २; २. १६, ७; ४३, २; ३. ४१, ४; ४. २२, ५; ७. ३७, १; ८. १, २०; १०. ३९, ४; ४३, ६; ५०, ४.
सु॒वं १. १६४, २६; ७. ३८, ४; ८. १०२, ६.
सऽवयसः १. १६५, १.
सऽवयसा १. १४४, ३; ४.
सऽवर्णा १०. १७, २.
सु॒वान् १. १२६, १; ४. २६, ७; १०. १५८, २.
सु॒वायं १. ११३, १; २. ३८, १; ३. ५६, ७; ४. ५४, ५.
सु॒वासः ४. ५४, ६.
सु॒वि॒तः १. २४, ३; २. ३८, ११; ३. ५६, ६; ४. ५४, २; ३; ५. ८२, ५; ६. ७१, ६; ९. ६७, २६; १०. ३५, ७; १४९, ५; १५८, २.
सु॒वि॒त॒रिति॑ १. ३५, ११; ३. ५४, ११; ४. ५४, ५; ६; ५. ८१, ४; ५; ८२ ४; ६. ७१, ३; ७. ३७, ८; ३८, २; ९. ६७, २५; १०. ९३, ९.
सु॒वि॒ता १. २२, ८; ३४, १०; ३५, २–४; ८; ९; ३६, १३; ७३, २; १०७, ३; ११०, ३; १२३, ३; १२४, १; १५७, १; १६४, २६; १८६, १; २. १, ७; ३१, ६; ३८, १; ४; ८; ३. ३३, ६; ५४, ११; ५५, १९; ५६, ७; ४. १३, २; ५३, २–७; ५४, १; ५५, १०; ५. ४२, ३; ५; ४८, ५; ४९, ४; ८१, २; ३; ८२, ३; ८; ९; ६. ४९, १४; ५०, ८; १३; ७१, ५; ७. १५, १२; ३५, १०; ३८, ३; ४०, १; ४५, १; ३; ६३, ३; ६६, ४; ७६, १; ८. २७, १२; ८६, ५; ९. ८१, ४; ९७, ४८; ११०, ६; १०. १०, ५; १२, ८; १७, ४; २७, १८; ३१, ४; ३४, ८; [illegible] ३६, १४^{१}; ८५, ९; १३; २४; ३६; ८७, १८;

९२, ४
४; ०; १००, १; ३; ८; ९; १३०,
१, १३९, १; १४९, १[३]; २; ४;
१८, ३; १६१, ४; १७४, ३;
१७५, १; ४.
सविताऽईव १. ९५, ७; १९०, ३; ४. ६, २; ७. ७९, २.
सवितारं १. २२, ५–७; ३५, १; ४४, ८; २. ३८, ९; ३. २०, ५; ६२, १२; ५. ४६, ३; ४९, १; २; ८२, ७; ६. २१, ९; ५०, १; ७. ४५, ४; १०. ६६, ४; १४१, ५.
सवितुः १. ३५, ५; ६; ११०, २; ११३, १; १५९, ५; २. ३८, ३; ६; ७; १०; ३. ३८, ८; ५६, ७; ६२, १०; ११; ४. ५३, १; ५४, ४; ५. ८१, १; ८२, १; २; ६; ६. ७१, २; ७. ३८, ४; ६; ५२, ३; ८२, १०; ८. १०२, ६; १०. ३६, १२; १३; ६४, ७; १४९, ३; १८१, १.
सवित्रा २. ३८, ५; ४. ३४, ८.
सवित्रे २. ३०, १; ६. १५, १६.
सवींमनि ४. ५३, ३; ६. ७१, २; ८. १८, १; १०. ३६, १२; ६४, ७.
सऽवृर्धः १०. ३०, १०.
सवे ५. ८२, ६.
सऽवेंदसा १. ९३, ९.
सवेर्न ९. ६७, २५.
सव्यः १. ८२, ५.
सव्यतः २. ११, १८.
सव्यं ८. २४, ५.
सव्या २. २७, ११.
सव्यां ८. ४, ८.
सव्यांय १०. ४९, ५.
सव्येर्न १. १००, ९; ५. ३६, ४; ८. ८१, ६.
सऽव्रंता ६. ७०, ३.
सव्रंते इति सऽव्रंते १०. ६५, ८.
सश्चत् २. २२, १–३.
सश्चत १. ६४, १२; ३. १६, २; ७. १८, २५; २६, ४; ९०, ३.
सश्चतः १. ४२, ७; ३. ९, ४; ७. ९७, ४.
सश्चंति १. १०१, ३.
सश्चंते २. १६, ४.
सश्चसि ८. ५१, ७.
सश्चिम ८. २५, १७; ९. १६, २.
सश्चिरे १. ११०, ६.
सश्चिरे १. ८४, १२; २. १, १३; ५. २०, २; ६४, ३; ६७, ३.
सश्चुः ६. ३६, ३.
सश्चे ५. ३३, ८.
ससतः १. १२४, ४; १२५, ७.
ससतांऽईव १. ५३, १.
ससतींऽईव १. १३४, ३.
ससस्थ ३. ३०, ९.
ससंतः ४. ३३, ७.
ससंतं १. १०३, ७; ४. ५१, ५; ६. २०, ६.
ससंतु १. २९, ४; ७. ५५, ५.
ससंतु १. १२४, १०; ४. ५१, ३.
ससं ८. ७२, ३; १०. ७९, ३.
ससर्जे १. १०३, २; ५. ८५, ३.
ससर्परीः ३. ५३, १५; १६.
ससऽवांसः ४. ८, ६; ४२, १०; ८. ५३, ७; ५४, ६; १०. १४८, १.
ससऽवांसं ३. ३४, ८.
ससऽवान् ३. २२, १; ६. ४४, ७; ७. ८७, २; ९. ७४, ८; १०. ११, ५; २९, २.
ससस्यं ३. ५, ६; ४. ५, ७; ७, ७; ५. २१, ४.
ससहः ८. १९, २०.
ससहत् ५. २३, १; ६. ३३, १; ८. १९, १५.
ससहानः १. १३१, ४.
ससहिः १. १००, ३; १०२, ९; १७१, ६; २. २२, ३; २३, ११; ३. १६, ४; ३७, ६; ८. १२, ९; ९. ४, ८; १०. १३३, ४; १४५, ५.
ससहिं १. १०२, १; ८. १५, ४; ६१, ३; १२; ७०, ४.
ससहिषे १०. १८०, १.
ससहीष्ठाः ६. ४५, १८.
ससहे १०. १०४, १०.
ससहे ८. ९६, १५.
ससह्यात् ५. ७, १०[२].
ससह्यामं १. ८, ४; ८. ४०, ७; ९. ६१, २९.
ससह्याम १. १३२, १.
ससव्हांसः ७. ९२, ४.
ससव्हांसं ८. १६, १०; ४६, १६.
ससव्हान् १. १००, ५; ९. ११०, १२.
ससादं १. ६७, ४; ७. ४, ५.
ससाद १. २५, १०; ३. १, १८; ५. १, ५; ६. १, ६; ७. ६, ६; ८. २९, २; १०. ९९, २.
ससांन ३. ३१, ७; ३४, ८; ९.
ससान ३. ३४, ९[३].
ससारं ४. ३०, ११.
ससार ९. ८६, १३.
ससाहं ५. २५, ६.
ससाह ८. ८६, ५.
ससूव ४. १८, १०; ७. २०, ५; १०. ८६, २३.
ससृजानः ७. ८, २.
ससृजानासंः ९. ९७, २०.
ससृजे ३. ३९, ४; ७. १८, ४; ३६, १; १०. ८, ८.
ससृज्महें १. ८१, ८; ६. १६, ३७; ८. ९८, ७.
ससृज्यात् १. २४, १३.
ससृज्रिरे ८. ६९, ५.
ससृमाणं ४. १७, १४.
ससृऽवांसः ८. १, १५; ९. २२, ४.
ससृवांसंऽइव ३. ९, ५.
ससेर्न १. ५१, ३.
सस्तः ६. २०, १३.
सस्तां १. २९, ३.
सस्तिं ८. ९७, ३.
सस्तु ६. ५५, ५[५].
सऽस्थावांना ८. ३७, ४.
सस्निं १०. १२०, २.
सस्निः २. १८, १; ३. १५, ५; ९. २४, ४; ६१, २०.
सस्निना २. २३, १०.
सस्निं ५. ३५, १; १०. ३८, ४; १३९, ६.
सस्नी इति ८. ३८, १.
सस्मिन् १. ५२, १५; १५२, ६; १७४, ४; १८६, ४; ४. ७, ७; १०, ८; १२, १; ७. ३६, ३; १०. ९५, ११.

सऽस्यर्दः १०. ११३, ४.
सस्राः १०. ६४, ८.
सस्राणः १. १४९, २.
सस्राथे इति १. १५८, १.
सस्निः १०. ९९, ४.
सस्नुः ७. १०१, ४; १०. १११, ८.
सस्नुः १. ५२, ५; ७३, ६; ५. ५३, २; ७; ७. ९०, ४; १०. ९५, ६.
सऽस्रुतः १. १४१, १; ४. २८, १; ९. ३४, ६.
सस्रुषीः १. ८६, ५.
सस्रे ७. ३६, १; ९५, १; १०. ७१, ४.
सस्वः १. ८८, ५; ५. ३०, २.
सस्वजाते इति १. १६४, २०.
सस्वजे ८. ४१, ३; ९. १२, ५.
सस्वरिति ७. ५९, ७.
सस्वर्तौ ७. ५८, ५.
सह १. २३, १७; २४; ३८, ६; ४८, १^{2}; ५०, १३; ११७, १३; १४३, १; ३. ५८, ६; ६०, ४; ५; ४. ४०, ३; ५. ५३, २; १४; ६२, १; ६; ७५, ६; ७८, ८; ६. २८, ३; ६०, १३; ७२, २; ७५, ७; ७. ३१, ८; ३५, ११; ६४, ३; ६६, ९; ८३, ६; ८. १, ३२; ५, ३४; २६, ७; २९, ८; ७६, १०; १०२, २; ९. ३७, ४; ८५, १; ९८, ७; १०. १७, १४; ३९, ११; ४३, ९; ४५, ११; ६५, १३; १४; ८४, ६; ८५, २४; ३८^{2}; ३९; ९७, २२; १०२, ६; १०७, २; ११३, ३; ११५, ७; १२१, ४; १२६, ७; १५७, २; १६२, २; १७२, १; १९१, ३.
सहः १. २४, ६; ३६, १८; ५१, १०; ५२, ११; ५५, ८; ५६, २; ५७, ६; ८०, १०; ८४, ५; १२; १०३, ३; १७४, ८; २. १६, २; ३४, ७; ३६, ५; ४. ४२, ६; ५. ११, ६; २३, ४; ३१, ३; ३२, ७; ४४, ६; ५७, ६; ६. १, १; ८, १; १८, ४; २५, ८; ४७, २७; ७. २५, ५; ३१, ७; ५६, १९; ९७, ६; ८. ४, ४; ५; १०; ९, १३; १५, २; २०, १३; १०२, ५; ९. ८, ८; ६५, १८; ९७, १०; १०. ४९, ८; ५०, १; ५६, ६; ८३, १; ८४, ६; १००, ६; ११६, ५; १७०, ३.
सहःऽकृत ८. ४३, १६.
सहःऽकृत १. ४५, ९; ३. २७, १०; ५. ८, १; ६. १६, ३७; ८. ४३, २८; ४४, ११.
सहःऽकृतः ८. ३, ४.
सहःऽकृतं ८. ९९, ८.
सहःऽकृतेन १०. ८३, १.
सहःऽजाः १. ५८, १; १०. १०३, ५.
सहःऽतमा ६. ६०, १.
सहःऽदाः १. १७१, ५; १७४, १; १०.
सहःऽदां ३. ३४, ८; ४७, ५; ६. १७, १३.
सहःऽभरिः ५. ४४, ३.
सहःऽभिः १. ६२, १०; ६. ६, ६; १९, १; ७. ६, ५; १०. ४६, ९; ५६, ५; ११६, ६.
सहःऽवृधं १. ३६, २; ३. १०, ९.
सहऽगोपाः १०. २७, ८.
सहऽछंदसः १०. १३०, ७.
सहऽजाः १०. ८४, ६.
सहऽजानुषाणि १. १०४, ८.
सहते ५. २, ९; ६. ४७, १; १०. ४३, ६.
सहऽदानुं ३. ३०, ८.
सहऽदेवः १. १००, १७.
सहध्यै ६. १, १; ७. ३१, १२.
सहध्वं १०. १०३, २.
सहन् ६. ७३, २.
सहंतः ५. ८७, ५.
सहंतं ५. २३, १; ८. ४६, २०.
सहन्ऽतमः १. १२७, ९.
सहंता ८. ४०, १.
सहंती ७. ५६, ५.
सहंते ६. ६६, ९; ७. ६०, १०.
सहंते १०. ३४, ९.
सहंत्य १. २७, ८; ६. १६, ३३; ८. ११, २.
सहऽप्रमाः १०. १३०, ७.
सहमानः ३. ४६, २; ६२, १५; ९. ११०, १२; १०. १०३, ५.
सहमानं ६. १८, १.
सहमाना १०. १४५, ५.
सहमानाः ४. ६, १०.
सहमानां १०. १४५, ६.
सहमानाय २. २१, २; ७. ४६, १.
सहऽमूरान् १०. ८७, १८.
सहऽमूलं ३. ३०, १७.
सहऽवत्सा १. ३२, ९.
सहऽवसुं २. १३, ८.
सहऽवा ३. ४९, ३; ६. १४, ५; १८, २; ७. ४५, ३.
सहऽवान् १. १७५, २; ३.
सहऽवानं १०. १७८, १.
सहऽवाहः ७. ९७, ६.
सहऽवीरं ३. ५४, १३; १०. ४०, १३.
सहऽशेय्याय १०. १०, ७.
सहसः १. १२७, १; १४१, १; १४३, १; २. ७, ६; ३. ११, ४; १४, १; २४, ३; २८, ३; ५. ४, ८; ११, ६; ३१, ३; ६. ५, १; ६, १; १२, १; ४९, २; ७. ५६, १९; ८. १९, २५; ६०, १३; ७१, ११; ७५, ३; ९. ७१, ४; १०. ११, ७; ४५, ५; ११५, ७; १४२, १; १५३, २; १७६, ४.
सहसः १. २६, १०; ४०, २; ५८, ८; ७४, ५; ७९, ४; १४१, १०; ३. १, ८; १४, ४; ६; १६, ५; १८, ४; २५, ५; २८, ५; ४. २, २; ११, ६; ५. ३, १; ६; ९; ४, ६; ६. १, १०; ४, १; ५, ५; ११, ६; १३, ४–६; १५, ३; १८, ११; २०, १; २१, ११; ५०, ९; ७. १, २१; २२; ३, ८; ७, ७; १५, ११; १६, ४; ८. १९, ७; १२; ६०, २; ८४, ५; १०. ५०, ६.
सहसा १. २३, ९; ५०, १३; ५१, १०; ८०, १०; ९६, १; ९८, २; १२७, ९; १०; २. १७, १; ४. १८, ८; २८, २; ५०, १; ५. १, ८; ३, १०; ८, ५; १२, २; ६. ५, ६; ४४, २२; ४८, ५; ६०, १; ६६, ९; ७. १८, १३; ६०, १०;

८. ४, ५; १०. ४९, ८; ६१, ९; ८३, १; १०३, ७; १०८, ९.
सहसानः २. १०, ६; ४. १७, ३.
सहसानं ५. २५, ९; ७. ७, १.
सहसाने १. १८९, ८.
सहऽसामानं १०. ११४, १.
सहंसाऽवन् ५. २०, ४; १०. २१, ४.
सहसाऽवन् १. ९१, २३; १८९, ५; ३. १, २२; ६. १५, १२; ७. १, २४; ४, ६; १९, ७; ४३, ५; १०. ९३, ११; ११५, ८.
सहसिन् ४. ११, १.
सहंसे १. १६, ६; ३. ५१, ४; ४. २०, ६; ६. १, १; ३८, ५; ७. ९८, ३; १०४, ३; १०. ७३, १.
सहऽस्तोमाः १०. १३०, ७.
सहस्य १. १४७, ५; २. २, ११; ५. २२, ४; ७. १, ५; १६, ८; १०. १, ७; ८७, २२.
सहस्यं ७. ४२, ६.
सहस्येन ७. ५५, ७.
सहस्यैः ५. २९, ९.
सहस्रऽअक्षः १. ७९, १२; १०. ९०, १.
सहस्रऽअक्षरा १. १६४, ४१.
सहस्रऽअक्षा १. २३, ३.
सहस्रऽअक्षेण १०. १६१, ३.
सहस्रऽअप्साः ९. ८८, ७.
सहस्रऽअर्घं १०. १७, ९.
सहस्रऽऊतिः ९. ६२, १४.
सहंस्रऽऊते ८. ३४, ७.
सहस्रऽकेतुं १. ११९, १.
सहस्रऽचक्षसं ९. ६०, १; २.
सहस्रऽचक्षसे ९. ६५, ७.
सहस्रऽचक्षाः ७. ३४, १०.
सहस्रऽचेताः १. १००, १२.
सहस्रऽजित् ९. ७८, ४; ८४, ४.
सहस्रऽजित् १. १८८, १; ५. २६, ६; ९. ५५, ४; ८०, ४.
सहस्रऽदक्षिणाः १०. १५४, ३.
सहस्रऽदक्षिणे १०. ३२, ५.
सहस्रऽदाः १०. ६२, ११.
सहस्रऽदातमं ६. ४५, ३३.
सहस्रऽदातु ९. ७२, ९.
सहस्रऽदानः ७. ३३, १२.
सहस्रऽदाना ३. ३०, ७.
सहस्रऽदाम्नीं १. १७, ५.
सहस्रऽद्वारं ७. ८८, ५.
सहस्रधा १०. ११४, ८[२].
सहस्रऽधारः ९. १३, १; ५२, २; ८६, ७; ३३; ८९, १; ९६, ९; ९७, ५; १९; १०१, ६; १०७, १७; १०९, १६; १९; ११०, १०.
सहस्रऽधारं ९. २६, २; ८०, ४; १०८, ८; ११.
सहस्रऽधारा ४. ४१, ५.
सहस्रऽधारां १०. ७४, ४.
सहस्रऽधारे ९. ७३, ४; ७; ७४, ६.
सहस्रऽनिर्णिजं ८. ८, १५.
सहस्रऽनिर्णिजा ८. ८, ११.
सहस्रऽनीतिः ९. ७१, ७.
सहस्रऽनीथः ३. ६०, ७; ९. ८५, ४; ९६, १८.
सहस्रऽनीथाः १०. १५४, ५.
सहस्रऽपर्णः ८. ७७, ७.
सहस्रऽपाजसः ९. १३, ३; ४२, ३.
सहस्रऽपात् १०. ९०, १.
सहस्रऽपाथाः ७. १, १४.
सहस्रऽपादं ८. ६९, १६.
सहस्रऽपोषं २. ३२, ५.
सहस्रऽपोषिणं ८. १०३, ४.
सहस्रऽपोष्यं ६. ३५, १.
सहस्रऽप्रधनेषु १. ७, ४.
सहस्रऽबाह्वे ८. ४५, २६.
सहस्रऽभरं ६. २०, १.
सहस्रऽभर्णसं ९. ६०, २; ६४, २५; २६; ९८, १.
सहस्रऽभृष्टिः १. ८०, १२; ९. ८३, ५; ८६, ४०.
सहस्रऽभृष्टिं १. ८५, ९; ५. ३४, २; ६. १७, १०.
सहस्रं १. ११, ८; २४, ९; ३०, २; ८०, ९; ११६, २; १२६, १; ३; १६७, १[३]; १८९, ८; २. १४, ६; ७; ४. १८, ४; २६, ७; ३१, १०; ३२, १७; ३८, ८; ४६, ३; ६. १८, ११; ३४, ३; ६९, ८; ७. २५, ३; ४६, ३; ६२, ३; ९१, ६; ९२, १; ९९, ५; ८. १, २४; ३, ४; ६, ४६; १२, ८; २१, १८; ३४, १६; ५७, ३; ७०, ५; ७८, १; ९. ५२, ५; ७८, २; ९१, ३; ९७, २९; १०६, ६; १०. १५, १०; १८, १२; ६२, ७; ८; ७३, ३; ७९, ५; ९७, २; ९८, ४; १०२, २; ५; ९; ११४, ८.
सहस्रऽमघं ७. ८८, १.
सहस्रऽमीळ्हे १. ११२, १०.
सहस्रऽऊतिः १. ५२, २.
सहस्रऽमुष्क ६. ४६, ३.
सहस्रऽमुष्कं ८. १९, ३२.
सहस्रऽभरः २. ९, १.
सहस्रऽयामा ९. १०६, ५.
सहस्रऽरेताः ४. ५, ३; ९. ९६, ८; १०९, १७.
सहस्रऽवत् ३. १३, ७; ८. २४, २९; १०. ९४, २.
सहस्रऽवर्चसं ९. १२, ९; ४३, ४.
सहस्रऽवल्शं ७. ३३, ९; ९. ५, १०.
सहस्रऽवल्शाः ३. ८, ११.
सहस्रऽवाजं १०. १०४, ७.
सहस्रऽवाजया ८. ९२, १०.
सहस्रऽवीरं १. १८८, ४.
सहस्रऽशः ८. ३४, १५.
सहस्रऽशीर्षा १०. ९०, १.
सहस्रऽशृंगः ५. १, ८; ७. ५५, ७.
सहस्रऽशोकाः १०. ९६, ४.
सहस्रऽसाः १. १८८, ३; ४. ३८, १०; ९. ४७, ३; ८२, ५; ८७, ४; ९६, १४; १०. ६४, ६; १७८, ३.
सहस्रऽसातमः १. १७५, १; ३. १३, ६.
सहस्रऽसातमं १. ९, ८; ६. ४५, ३३.
सहस्रऽसातमा १. १०, १०.
सहस्रऽसां १. १०, ११; ११७, ९; ११८, ९; ५. ३४, ९; ८. १०३, ३; ९. ५४, १.
सहस्रऽसावे ३. ५३, ७; ७. १०३, १०.
सहस्रऽस्तरीः १०. ६९, ७.
सहस्रऽस्थूणं ५. ६२, ६.
सहस्रऽस्थूणे २. ४१, ५.
सहस्रस्य १. १२६, ४.

सहस्रा १. ५३, ९; ६२, १०; ११६, २१; १३३, ७; ४. १६, १२; १३; २८, ३; ३०, २१; ३२, १८; ५. ३०, १२; १४; ३३, ९; ३७, ३; ६. १८, १३; २६, ५; ६; ४८, १५; ६३, १०; ७. १८, १४; ८. २, ४१; ४, २०; ५, ३७; ६, ४७; ३२, १८; ३३, ५; ३४, १४; ४५, १२; ४६, २२^{२}; २९; ५६, २; ९. ८७, ५; ९७, २५; ५३; १०. २३, ५; २८, ६; ४८, ४; ७३, ४; ८०, ४; ५; ९८, १०; ११.

सहस्राणि १. ५३, ६; २. १, ८; ३. ९, ९; ४. २९, ४; ३०, १५; ७. ३२, ५; ८. ५१, २; ६१, ८; ९. ५८, ३; ४; १०. ९८, ९.

सहस्रात् १. १०२, ७; ५. २, ७.

सहस्राय १. ११६, ९; ८. १, ५.

सहस्रिणः १. ३१, १०; १६७, १; २. २, ७; ४१, १; ४. ४८, ५; ७. २६, ५; ८. १, ९; ७५, ४; ९. ३३, ६.

सहस्रिणं १. ५, ९; ६४, १५; १२४, १३; ३. १४, ६; २२, १; ४. ४९, ४; ५. ५४, १३; ६. ८, ६; ८. ५, १५; ३३, ३; ४३, १५; ६४, ५; ८८, २; ९३, २१; ९. १३, ५; २०, २; ३८, १; ४०, ३; ५७, १; ६२, १२; ६३, १; १२; ६५, २१; ६७, ६; ९८, ४; १०. २४, १; ४७, ५.

सहस्रिणीं ६. ४५, ३२; ७. १५, ९.

सहस्रिणीः १. १८८, २; २. ६, ५; ९. ४०, ४; ६१, ३.

सहस्रिणीभिः १. ३०, ८; १३५, ३; १०. १३४, ४.

सहस्रियं ७. ५६, १४.

सहस्रियासः १. १६८, २.

सहस्री ६. १५, १२; ७. ५८, ४.

सहस्रे ८. ६५, ११.

सहस्रेण १. १३५, १; ८. ६५, १२.

सहस्रेणऽइव ८. ४, ६; ४९, १; ५०, १.

सहस्रेभिः ८. ७३, १५.

सहस्रेषु १. २९, १–७.

सहस्रैः १. १८०, ८; ४. ३८, ९; ५. २७, १; ३०, १३; ८. १, ३३; ७३, १४; ९६, १३.

सहस्व ३. २४, १; ३०, १६; १०. ८४, ३.

सहस्व १०. ८४, २.

सहस्वः १. १८९, ४; ३. १४, २; ४; ५. ९, ७; २३, २; ७. ४, ४; ८. ४३, ३३.

सहस्वत् १. ६, ८.

सहस्वतः १. ९७, ५; २. १३, ११.

सहस्वता १०. ८३, १.

सहस्वति १०. १४५, २.

सहस्वती इति १०. १४५, ५.

सहस्वते १. १२७, १०; ५. ७, १; ८. १०२, ७.

सहस्वान् ६. ५, ६; २२, १; १०. १०३, ५.

सहांसि ४. २२, ९; ६. ६६, ९; ७. २१, ७; १०. ४४, १.

सहाः ८. २०, २०.

सहानां १०. ६, ५.

सहावहै १०. १४५, ५.

सहावान् ९. ९०, ३; १०. ८३, ४.

सहासः ७. ३४, २४.

सहिषीमहि ८. ४०, १.

सहिष्ठ ६. १८, ४.

सहीयसः १. १७१, ६; ४. ५५, १.

सहीयसा ८. ३९, ५; १०. १४५, ६.

सहीयसि ५. ७९, २.

सहीयसे १. ७१, ४.

सहीयान् १. ६१, ७; १०. १७६, ४.

सहुरिः २. २१, ३; ४. ३८, ७; ७. ५८, ४; १०. ८३, ४; ९२, ८.

सहुरिं ८. ४६, २०.

सहुरी इति ६. ६०, १.

सहुरे ४. २२, ९; १०. ८३, ६; ८४, २; ५.

सहूतिऽभिः १. ४५, १०; ८. ७५, ५.

सऽहूतिं १०. ८९, १६.

सऽहूती २. ३३, ४; ७. २७, ४.

सहूती इति सऽहूती १. ९३, ९.

सहो इति ८. ७, ३२; १०. ९३, ९.

सह्यसः १. १२०, ४; १०. ९३, १.

सह्यसे १०. ११५, ६.

सह्याः १. १५२, ७; २. ११, ४.

सह्याम १०. ८३, १.

सह्युः ७. ९०, ६.

सह्योः ६. १८, १२.

सह्वांसः ९. ४१, २.

सह्वान् १. ५८, ५; २. २०, ६; ३. ११, ६; ४. २१, २; ६. ६८, ७; ७. १२, २; ९. २०, १; ९०, ३; १०५, ६.

सा १. ४८, १०; १२–१४; ९५, ८; ११७, १८; १२१, १५; १२२, ७; १२९, ८; १५१, ४; १६४, ८; १७; २७; २९; ४१; १६९, ३; १७२, २; १८४, ४; १८६, ११; २. ११, २१; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; ३. १, २३; ३९, २; ५३, ४; १६; ५५, १३; १५; ४. २, १०; ४, ७; १०, ८; ४१, ५; ४३, ७; ५०, ११; ५७, ७; ५. ८, ५; ३०, १४; ४१, १८; ६१, ५; ७९, २; ३; ६. १७, ९; ६१, ९; ६४, ४; ५; ६६, ३^{२}; ७. ४६, ३; ५६, ५; ५७, ४; ५८, ६; ७०, २; ७७, ६; ८६, ६; ९६, २; १०४, १७; ८. १८, ७; २७, १८; ७४, ८; ९; १००, ११; १०. १०, ४; २७, १२; २४; ३१, ५; ३७, २; ५२, २; ५४, २; ६१, १८; ६३, १६; ६४, १५; ६५, ६; ८९, १४; ९५, ४; १२७, ४; १४५, ३.

साकं १. ३७, २; ४७, ७; ५२, १; ६४, ४; ८०, ९; १३५, ८; १३७, २; १५५, ६; १६१, २; १६४, ४८; १६६, १३; १७९, २; १९१, ३; ७; २. ५, ४; १३, ९; २२, ३^{३}; २४, ४; ३. १२, ६; ३१, १५; ५१, ९; ४. १९, ५; २६, ३; ७; ५. २९, ६; ७; ५५, ३^{२}; ७९, ८; ६. २७, ६; ३०, ५; ६६, २; ७. ३६, ६; ९९, ५; ८. ९, १६; २७, १४; ७७, ४; १०१, २; ९. ७, ७;

६१, ६; ७२, २; ९७, ८; **१०.** २८, ६; ५४, ३; ६७, ५; ७३, ६; ८६, १४; २३; ९४, १; ६; ९७, १३[२]; १०३, १.

साकंऽउक्षः **९.** ९३, १.

साकंऽउक्षे **७.** ५८, १.

साकंऽजानां **१.** १६४, १५.

साकंऽयुजा **१०.** १०६, ३.

साकंऽवृधा **७.** ९३, २; **९.** ६८, ३.

साक्षते **१०.** १२०, ६.

साक्षाम **७.** ९८, ४.

साक्षि **१०.** ४९, १.

साक्ष्व **३.** ३७, ७.

साख्यस्य **२.** ११, १९.

साचीऽइव **१०.** १४२, २.

साच्यं **१.** १४०, ३.

सात् **५.** ४५, २; **७.** २८, ४.

सातं **१०.** १०२, ११.

सातये **१.** ४, ९; १०२, ३; ५; १११, ४; १३०, ६[२]; १३८, ४; १४३, ६; **३.** ३१, १९; ३६, १; ५४, १७; ५६, ६; **५.** ५, ४; ९, ७; ३९, ३; **६.** १९, २; ५६, ५; ६०, १३; १५, ९; ६७, ५; ८३, ६; ९५, ३; **८.** ३, ५; ५, ९; ४५, ९; **९.** ७, ९; ५६, ३; ६८, ७; ८८, २; **१०.** ३५, १०; ३८, १; ६३, ९; ९३, १०; १४३, ५.

साता **१.** ११२, २२; १३१, ३; **६.** १०, ३; ४६, १; **९.** ६६, १८.

सातानि **२.** २४, १०; **८.** ४, २०.

सातिः **१.** १६८, ७.

सातिं **१.** ६, १०; १११, ३[४]; ५; **८.** २३, २९; **९.** ६१, ९; ९७, २५.

सातिषु **७.** ८२, ९.

सातीः **८.** ५, ९.

सातुः **४.** ६, ७.

सातेन **१०.** १६७, ४.

सातौ **१.** ३६, १७; १६९, २; १८०, ८; **२.** १९, ४; ३०, ५; **४.** २४, ३; **६.** १०, ६; १९, ७; २०, ५; २६, १; २; ४४, ९; **७.** २१, ७; ३०, २; ३६, ८; ६०, ११; **१०.** ६१, २४; ७४, १.

सादतऽयोनिं **५.** ४३, १२.

सादयं **१.** १५, ४; **३.** २९, ८; **१०.** ३५, १०.

सादय **१.** ३१, १७; ४५, ९; **३.** ५७, ५.

सादयत **१०.** ३०, १४.

सादयध्वं **५.** ४३, १२.

सादयतः **७.** ४४, २.

सादयंते **३.** ६, ३.

सादयात् **८.** ४४, ३.

सादि **१०.** ९३, ५.

सादि **२.** ११, ८; १८; **७.** ७३, २.

सादे **१.** १६२, १७.

साध **४.** ३, ८.

साध **३.** १, २३.

साधत् **२.** १९, ३.

साधत **५.** ४५, ३.

साधति **१.** ९४, २; **६.** ७०, ३.

साधतऽइष्टिं **३.** २, ५.

साधते **१.** १४१, १; **९.** ७१, ३.

साधते **८.** १९, १०.

साधथः **३.** ३८, ९; **४.** ५६, ७.

साधदिष्टिऽभिः **३.** ३, ६.

साधन् **३.** १, १७; १८; ५, ३; **४.** १, ९; १६, ३; **६.** ६६, ७; **७.** ३४, ४.

साधन् **१.** ९६, १.

साधनः **३.** २७, ८; **९.** १०५, ३.

साधनं **१.** ४४, ११; **३.** ३, ३; २७, २; **५.** २०, ३; **८.** ६, ३; २३, ९; **९.** ६२, २९; **१०.** २६, ४; ९२, २.

साधंतः **८.** ४०, ९; **१०.** ७४, ३.

साधंता **१.** २, ७.

साधंतां **६.** ५३, ४.

साधयं **१.** ९४, ३.

साधय **१.** ९४, ४; **६.** ५६, ४; **९.** ९, ८.

साधयंतं **७.** ६६, ३.

साधयंती **२.** ३, ८.

साधवः **६.** १६, ४३; **८.** १९, ८.

साधसे **८.** ७१, १२.

साधारणः **४.** ३२, १३; **७.** ६३, १.

साधारणं **९.** ४८, ४.

साधारण्याऽइव **१.** १६७, ४.

साधिष्ठः **५.** ३५, १; **८.** ५३, ७.

साधिष्ठेभिः **१.** ५८, १; **७.** ६४, ३.

साधु **८.** ३२, १०.

साधु **१.** १२४, ३; **२.** ३, ६; २७, ३; **६.** ९, ५; १५, १६; **७.** ४३, २; **१०.** १८, ५.

साधुऽअर्याः **१०.** ६८, ३.

साधुः **१.** ६७, १; ७०, ६; ७७, ३; **२.** २७, ६; **३.** १८, १; **५.** १२, ६; **७.** ३७, ४; **८.** ७७, ११.

साधुऽकर्मा **१०.** ८१, ७.

साधुना **१.** १५५, १; **१०.** १४, १०.

साधुऽभिः **१.** १३८, ४; **८.** ८४, ९.

साधुं **५.** १, ७.

साधुऽया **१.** ४६, ११; १७०, २; **५.** ११, ४; **१०.** ३३, ५; ६६, १२; १३.

साधू इति **२.** २७, १५.

साधे **१०.** ३५, ९.

साधोः **३.** ४८, १; **४.** १०, २; **७.** ८, ३.

साध्याः **१.** १६४, ५०; **१०.** ९०, ७; १६.

साध्वीः **२.** २४, ८.

साध्वीं **१०.** ५३, ३.

सानवि **४.** ४५, १; **६.** ४८, ५; **८.** १०३, २; **९.** ३१, ५; ३७, ४; ५०, २; ६३, २७; ७०, ८; ७९, ४.

सानसि **१.** ७५, २; **३.** ५९, ६.

सानसिः **१.** १७५, २; **९.** ८५, ५; १००, ४; १०६, २.

सानसिं **१.** ८, १; **४.** १५, ६; **८.** २१, २; **९.** १०६, ३; **१०.** ६३, १४; १४०, ४; ५.

सानसी इति **७.** ९३, २.

सानु **१.** ५४, ४; ५८, २; ६२, ५; ११७, १६; **२.** ३५, १२; **३.** ५, ३; **४.** ५५, ७; **५.** ६०, ३; **६.** ६, ४; ६१, २; ७५, १३; **७.** २, १; ७, २; **८.** ९६, २; **९.** १६, ७; ८६, ८; ९; **१०.** २७, १५; ६२, ९; ७०, ५.

सानुकः २. २३, ७.
सानुनः ५. ५९, ७.
सानुना ७. ३६, १; १०. ७५, २.
सानुनि १. १५५, १.
सानु १. १०, २; ८०, ५; ६. ३९, २; ६७, ६.
सानुषक् १. १७६, ५.
सानुषु १. १२८, ३[२]; २. ३, ७.
सानूनि ६. ७, ६.
सानोः १. १०, २.
सानौ १. ३२, ७; ८०, ६; १४६, २; २. ३१, २; ७. ४३, ३; ९. २६, ५; ८६, ३; ९१, १; ९२, ४; ९५, ४; ९६, १३; ९७, ३; १२; १६; १९; ४०; १०. ६१, ६; १२३, २.
साप्त २. १९, ७.
साप्तस्य ८. ५५, ५.
साप्तानि १. २०, ७.
साप्तेभिः ८. ५९, ५.
साप्यः १०. ४८, ९.
साप्यं ६. २०, ६.
साम १. ६२, २; १६४, २४; १७३, १; २. ४३, २; ४. ५, ३; ८. २९, १०; ८१, ५; ९८, १; ९. ९६, २२; १११, २; १०. ९३, ८; ९९, २; १३५, ४.
सामगाःऽइव २. ४३, १.
सामऽगां १०. १०७, ६.
सामन् १. १४७, १; ८. ८९, ७; १०. ५९, २.
सामनां ३. ३०, ९.
सामनौ १०. ८५, ११.
सामन्यः ९. ९६, २२.
सामऽभिः १. १०७, २; ८. १६, ९; १०. ३६, ५; ७८, ५.
सामऽभृतं ७. ३३, १४.
सामऽविप्रं ५. ५४, १४.
सामानि ५. ४४, १४; १५; १०. ९०, ९; १३०, २.
सांऽतपनाः ७. ५९, ९.
साम्नः २. २३, १६.
साम्नःऽसाम्नः २. २३, १७.
साम्ना ८. ९५, ७.
साम्ने ८. ४, १७; ६, ४७.
सांऽराज्यस्य ८. २५, १७.
सांऽराज्याय १. २५, १०; १४१, १३; ८. २५, ७.
सांऽराज्येन ७. ४६, २.
सांऽवरणौ ८. ५१, १.
सायक १०. ८३, १; ८४, ६.
सायकं १. ३२, ३; ८४, ११.
सायकस्य ३. ५३, २३.
सायकानि २. ३३, १०.
सायकेन १०. ४८, ४.
सायं ५. ७७, २; ८. २, २०; १०. १४६, ३; ४.
सारघाऽइव १०. १०६, १०.
सारघेण ८. ४, ८.
सारथयः १. ५५, ७.
सारथये २. १९, ६; ६. २०, ५.
सारथिः १. १४४, ३; १५८, ६; ६. ५७, ६; १०. १०२, ६.
सारे ३. ५३, १९.
सारमेय ७. ५५, २; ३.
सारमेयौ १०. १४, १०.
सारस्वतेभिः ३. ४, ८.
सार्ञ्जयः ६. ४७, २५.
सालावृकाणां १०. ९५, १५.
सालावृकान् १०. ७३, ३.
साळ्हा ७. ५६, २३.
सावः १०. ४९, ७.
सावर्णेः १०. ६२, ११.
सावर्ण्यस्य १०. ६२, ९.
साविषत् १. १६४, २६; ७. ४५, ३; १०. ९९, ७; १००, ३; ८.
सावीः २. २८, ९; ५. ८२, ४; ६. ७१, ६.
साशनानशने इति १०. ९०, ४.
साहऽदेव्यः ४. १५, ७; ९.
साहऽदेव्यं ४. १५, १०.
साहऽदेव्यात् ४. १५, ८.
साहि ४. ११, २.
सिंहः १. १७४, ३; ३. २, ११; ४. १६, १४; ९. ९७, २८; १०. २८, १०.
सिंहं १. ९५, ५; ५. १५, ३; ९. ८९, ३; १०. २८, ४.
सिंहंऽइव ३. ९, ४; ५. ७४, ४; १०. ६७, ९.
सिंहस्य ५. ८३, ३.
सिंहाः ३. २६, ५.
सिंहाःऽइव १. ६४, ८.
सिंह्यं ७. १८, १७.
सिक्तः ९. ९७, १५.
सिक्तं १. १३०, २.
सिक्तयः १०. १००, ११.
सिक्ता ६. ७०, ३.
सिचः ९. ८१, ३.
सिचं ३. ५३, २.
सिचा १०. १८, ११.
सिचामहे २. १६, ७.
सिचौ १. ९५, ७; १०. ७५, ४.
सिच्यते ९. ६९, २.
सिच्यते ४. ४९, २; ५. ५१, ४; ८. ९, ४; ९. १७, ४; २७, २; ३९, ५; ४२, ४; ६२, १३; ८६, ३३; १०. १६७, १.
सिच्यसे ९. ११, ८; ७८, २; ९८, १०.
सिंच ८. २४, १६; ३२, २४.
सिंच ५. ८३, ८; ८. २, २२; १०. १०१, १०.
सिंचत् ४. ४३, ६; १०. ६१, २; ७.
सिंचत २. १४, १; ८. २४, १३; ७२, १३; ९. ६३, १०; १९; १०७, १; १०८, ७; १०. ३२, ५; १०१, ७.
सिंचतः १०. ६४, १४.
सिंचतं ४. ५७, ५; ६. ७०, २.
सिंचतीःऽइव १०. २१, ३.
सिंचतु १०. १७, १३; १८४, १.
सिंचते ८. ४९, ६.
सिंचध्वं ७. १६, ११.
सिंचन् १. १२१, ६; १०. १०२, ११.
सिंचंति ८. ७२, १०.
सिंचंति ९. ७१, ४.
सिंचंतु ८. ५३, ३.
सिंचं १०. २७, २.
सिंचसे १०. १०५, १०.
सिंचस्व ३. ४७, १.
सिंचात् ८. ९, ७.
सिंचामहै १०. १०१, ५.

सिंचामि ८. १७, ५.
सिंचे १. ३०, १; १०. १०१, ६.
सितं १. ११२, ५.
सितं ८. ५, ९.
सितां ४. १२, ६.
सिध्मः १. ३३, १३.
सिध्यंति १. १८, ७.
सिध्रं १. १४२, ८; १७३, ११; २. ४१, २०; ५. १३, २.
सिध्रयां ५. ४४, ६.
सिध्राः १०. ७, ४.
सिनं २. ३०, २; ३. ६२, १.
सिनंऽवत् १०. १०२, ११.
सिनीथः ७. ८४, २.
सिनीवालि २. ३२, ६.
सिनीवालि १०. १८४, २.
सिनीवाली २. ३२, ८.
सिनीवाल्यै २. ३२, ७.
सिंधवः १. ५२, १४; ६१, ११; ७२, १०; ७३, ६; ९०, ६; १०१, ३; १०५, १२; १२५, ४; ५; १४०, १३; १४३, ३; १५१, ९; १६८, ८; २. ११, १; २५, ५; २८, ४; ३. ३६, ६; ७; ४. २२, ६; ५. ४९, ४; ५१, ७; ५३, ७; ६२, ४; ६९, २; ६. १९, ५; ३६, ३; ५२, ४; ७. ३५, ८; ८. ६, ४; ३५; ७, ५; ४०, ८; ४४, २५; ५४, ४; ६९, १२; ९२, २२; ९६, १; ९. २, ४; १७, १; ३१, ३; ६२, २७; ६६, ६; १३; ८८, ६; १०८, १६; १०. ४०, ९; ४३, ३; ७८, ७; ९२, ५; १२४, ७.
सिंधवः ३. ३३, ९; ५६, ५; ७. ४७, ४; १०. ३०, ८; ९.
सिंधुः १. ६५, ३; ६६, ५; ९२, १२; ९४, १६; ९५, ११; ९६, ९; ९८, ३; १००, १९; १०१, ११; १०२, ११; १०३, ८; १०५, १९; १०६, ७; १०७, ३; १०८, १३; १०९, ८; ११०, ९; १११, ५; ११२, २५; ११३, २०; ११४, ११; ११५, ६; १२२, ६; १८६, ५; २. २५, ३; ३. ३२, १६; ४. २२, ८; ४३, ६; ५४, ६; ५. ५३, ९; ७. ९५, १; ८. २५, १४; २६, १८; ९. ९६, ७; ९७, ४५; १०७, १२; १०. ६४, ९; ६५, १३; ६६, ११; ७५, १; ३; ७–९.
सिंधुःऽइव १०. ६२, ९.
सिंधुपती इति सिंधुऽपती ७. ६४, २.
सिंधुऽभिः १. ३४, ८; ४. ३४, ८; ६. ५२, ६; ९. ८६, ११; ९६, १४.
सिंधुऽभ्यः १. २३, १८; १०९, ६; ७. ४७, ३; ९. ८६, २१; १०. ८९, १; ११.
सिंधुं १. ११, ६; ८३, १; ९९, १; ११२, ९; १४६, ४; १६४, २५; २. ११, ९; १५, ६; ३. ३३, ३; ५; ५३, ९; ४. ३०, १२; ५५, ३; ५. ४, ९; ३७, २; ७. ३३, ३; ८७, ६; ८. १२, ३; २०, २४; ९. ७०, १०; १०. ४३, ७; १०४, ८; १११, १०; १२३, ४.
सिंधुऽमातरः १०. ७८, ६.
सिंधुऽमातरं ९. ६१, ७.
सिंधुऽमातरा १. ४६, २.
सिंधुऽमाता ७. ३६, ६.
सिंधुऽइव १. ९७, ८; ५. ११, ५.
सिंधुऽवाहसा ५. ७५, २.
सिंधुषु १. १८२, ५; ८. २४, २७; ३९, ८; ९. ७२, ७; ८६, ८.
सिंधून् १. ३२, १२; ३५, ८; ९३, ५; २. १२, ३; १२; ४. १७, १; १८, ७; १९, ५; ६; ८; २८, १; ३३, ७; ४२, ७; ८. ५, २१; ३२, २५; ९६, १८; १००, १२; ९. ९०, २; १०. ३५, २; ८९, ७; १११, ९; १३३, २.
सिंधूनां १. ४६, ८; ९; ६५, ४; ३. ५, ४; ६. ४४, २१; ७. ५, २; १८, ५; ८. ४१, २; ९. १५, ५; ८६, १२; १९; ३३; ८९, २; १०. १८०, १.
सिंधून्ऽइव ६. ४६, १४.
सिंधो इति १०. ७५, २.
सिंधो इति ८. २५, १२; १०. ७५, ४; ६.
सिंधोः १. २७, ६; ८. ७२, ७; ९. १२, ३; १४, १; २१, ३; ३९, ४; ५०, १; ७३, २; ८५, १०; ८६, ४३; १०. १३७, २; १५५, ३.
सिंधोःऽइव १. ४४, १२; ४. ५८, ७; ९. ६९, ७; ८०, ५.
सिंधौ १. १२६, १; ८. २०, २५.
सिंधौऽइव १०. ११६, ९.
सिम ८. ४, १.
सिमः १. १०२, ६; १४५, २; १०. २८, ११.
सिमस्मात् १. ९५, ७.
सिमस्मै १. ११५, ४.
सिरासु १. १२१, ११.
सिरीः १०. ७१, ९.
सिलिकऽमध्यमासः १. १६३, १०.
सिष्णो इति ८. १९, ३१.
सिसक्त १०. १९, १.
सिसक्ति १. ५६, ४; ४. २१, ७; ५. ७३, ८; ६. ५०, ५; ६८, ३; ७. ७०, २; १०. ५, १; २७, १९; ९२, ९.
सिसक्ति १. ३८, ८; ६६, १; ७. ६७, ३; ९१, ३; ९. ८४, २.
सिसक्तु ५. ४१, १५; २०; ८. ७५, १३.
सिसक्तु १. १८, २; ७. ३७, ८; ९७, ३.
सिसक्षि १. ७३, ८.
सिसर्ति २. ३८, २.
सिसर्षि ३. ३२, ५.
सिसाय १०. २८, १०.
सिसासतः २. ३२, १; ८. ३, १२; १०३, ११.
सिसासतं १०. १४३, ३.
सिसासति ९. ७४, १; ७.
सिसासति १. १३३, ७; ७. ३२, १४; २०; ८. ६२, ३; ९. ३, ४; ७, ४.
सिसासतुः ९. ४७, ५.
सिसासते ८. ३, ११.
सिसासन् १. १३०, ३; ५. ३१, १; ६. ७३, ३; ९. ३५, ४; ७६, २; ९०, ४; ९६, १८; १०. १०२, ४.
सिसासनिः १०. ५३, ११.
सिसासंतः १. १४६, ४; ५. ६२, ९; ८. ९५, ६; ९. ६१, ११.

सिसासंतं १. ११२, ५.

सिसासंती १. १२३, ४.

सिसासंतीषु १. १७, ८.

सिसासवंः १. १०२, ६.

सिसाससि १०. १०२, १२.

सिसासुसि ८. ९५, ९; ९. २३, ६.

सिसिचतुः ७. ३३, १३.

सिसिचुः २. २४, ४.

सिसिचे ३. ३२, १५.

सिसृतं ७. ६२, ५.

सिसेत् ८. ६७, ८.

सिसेध १. ३२, १३.

सिस्रंतः ५. ५४, १०.

सिस्रंतुः ८. ५९, २.

सिस्रंते १०. ३५, ५.

सिस्रते २. ११, ३; १७, ३; ३. ५२, २; ४. २२, ६; ५. १, १; ८. ५९, १; ९. ६६, ६.

सिस्वदत् १. १८८, १०.

सिस्वंप् ६. २०, १३.

सिस्वप् ६. २६, ६.

सिस्वपः १. १२१, ११.

सिस्विदानः ४. २, ६; ५. ४२, १०.

सिस्विदानाः ७. १०३, ८.

सीक्षंत ७. ६०, ११.

सीक्षंतः ६. १४, ३.

सीतां ४. ५७, ७.

सीते ४. ५७, ६.

सीदं ३. २९, ८; १०. १४, ४.

सीद १. ७६, २; १०४, १; २. २३, १; ३. २९, १०; ४१, ३; ५३, ३; ४. ३, २; ६. १५, १६; ९. ५९, ३; ८७, १; ९६, १३; १०. ९८, ४; ११२, ९.

सीदुः ६. ५, ३.

सीदंत् ५. ११, २; ६. १६, २३; ८. ७२, २; १०. १२, १; ६१, ४; ९९, ८; १२३, ५.

सीदत् ७. ३०, ३; १०. ४६, १; ६; ६१, ९.

सीदंत १. ८५, ६.

सीदत १. ५, १; २२, ८; २. ३, ४; ४१, १३; ९. ११, ६; १३, ९; ३९, ६; १०४, १; १०. ७०, ८.

सीदतं १. ४७, ८; ३. ६२, १८; ८. ८७, २; १०. १३, २.

सीदंतां १. १४२, ७.

सीदतां १. १८८, ६.

सीदंति ९. ६४, २०.

सीदति ४. ९, ३; ४; ९. ७, ५; ६; २०, ६; ३८, ४; ४०, २; ५७, ३; ६८, ९; ७०, ७; ८४, ४; ८६, ६; ९; ११; ९९, ६.

सीदंतु १०. ३६, ५.

सीदतु ६. १६, ४१.

सीदंन् १. ६५, ५; ६. १६, ३५; ७. ३४, १६; ९. ३२, ४; ६१, २१; ६२, ८; ६४, ११; ६५, १९; ८६, २२; ९२, २; ६; ९५, १; ९६, २३; १०७, १८.

सीदन् १. ६५, १; ७२, ५; ८५, ७.

सीदंतः ८. २१, ५; ९. ६४, २९.

सीदंतु १. २६, ४; ६. २८, १; १०. ७०, ११.

सीदंतु १. १३, ९; ४४, १३; १४२, ९; २. ४१, २१; ५. २६, ९; १०. ७०, ६.

सीदसि १. १४, ११; ८. ६१, २; ९. ६३, २; ८६, ३५; ४७; ९९, ८; १०७, ४.

सीदस्व १. ३६, ९.

सीदाति ९. ९७, ४.

सीं १. ३३, ९; ३६, १; ३७, ६; ९; ६१, ११; ९५, २; १००, १४; ११६, २०; ११७, १६; १९; १२२, ६; १४०, ५; १४१, ९; १६०, २; १७९, ५; २. २८, ४; ३६, १; ३. १, ६; २, १०; ७, ३; १४, ३; २३, ३; ३०, १४; ३८, ३; ५४, ६; ५६, ४; ४. २, ६; १३, ३; २२, ७; २८, ४; ३०, १०; ११; ३८, ३; ८; ४३, ५; ५६, १; ५. ३१, ९; ४७, २; ८५, ७; ६. १, १; २०, ८; ४५, २३; ४८, ४; ६४, ३; ७. ७८, २; ८. ४०, ८; ६९, ६; ७०, ७; ८०, ८; १००, ७; १०. २५, ९.

सीमहि १. २५, ३.

सीरां १०. १०१, ३; ४.

सीराः १. १७४, ९; ४. १९, ८; १०. ४९, ९; ९७, ९.

सीलमांऽवती १०. ७५, ८.

सीव्यंतु २. ३२, ४.

सीव्यध्वं १०. १०१, ८.

सीव्यंन् २. १७, ४.

सीषपंत ७. ४३, ४.

सीसंधः २. २४, १.

सीसधः ६. ५६, ५.

सीसधाति ६. ४९, ८.

सीसधाम १०. १५७, १.

सु १. ९, ६; १०, ११; १७, ७; २६, ५; २७, ४; ३३, १; ३६, १३; ३७, १४; ३८, ६; ४५, ५; ४७, २; ५; ५२, १; ५३, १; ७६, २; ३; ८२, १; ८४, ३; ९३, १; ९४, १२; १०५, ३; १११, २; ११२, १–२३; ११८, १०; १२९, ५; १३३, ४^{२}; १३५, ९; १३६, १; १३८, ४^{२}; १३९, १; ७; ८; १४८, ३; १६४, २६; १६५, १४; १६९, ५; १७३, १२; १७९, ५; १८२, १; १८४, २; १९१, ६; २. ६, १; ११, १५; १४, ५; १६, ८; १८, ३; २०, १; २८, ६; ७; ३४, १५; ३५, २; ४१, ७; ३. १८, २; २४, २; ३०, ६; २१; ३१, १४; ३३, ९^{२}; ३६, १; २; ३७, २; ५३, २; ५४, ३; ५५, २; ५७, २; ४. १२, १; ४; ६; २०, ४; २२, १०^{२}; २६, ४; ३१, ३; ३२, ६; १४; ४३, ६; ५५, ४; १०; ५. ३०, ७; ३५, २; ४२, १३; ५४, १५; ६२, २; ६३, ६^{२}; ६७, ५; ७३, ४; ८; ७४, ९; १०; ८३, ७; १०; ८५, ५; ६. ११, ४; १२, २; १५, १; १६, १६; २१, ७; २४, ९; २५, १; २७, ७; ३३, १; ४५, ३३; ४६, ६; ४८, ३; ५६, ४; ७४, ४; ७. २०, १०; २२, ३; २६, ३; २९, २; ३२, १; ४२, ३; ५५, २; ५९, ५^{२}; ८६, ८;

८९, १; ९०, ७; ९३, ६; ८. १, १४; १९; २, १९; २०; ४२; ४, ३; ५, १३^{२}; ६, ३२; ३९; ४३; ७, १८; ३२; ३३; ८, २१; १३, २५; १७, ४; १८, १२; १८; २२; २०, १९; २२, ३; २४, १; ७; २६, १; १०; १५; २३; २७, ३; ३२, १९; ३४, १२; ४०, १; ४१, १; २; ४५, ८; ९; ४६, १०; १७; ५०, १; ५३, ६; ५९, ५; ६१, ५; ६७, १५; २१; ७०, ९^{२}; ७३, १७; ७५, ११; ८०, ३; ६; ८१, ८; ८२, ६; ९२, १४; ३०; ९३, २१; १००, ३; १०३, १; ९. २९, ५; ४९, १; ६१, १३; ६५, ५; ८१, ३; ११०, १; १०. १०, १४; १६, १४^{२}; १८, १२; २७, १; २०; २८, ४; ३२, १^{२}; २; ३३, ३; ४०, ११; ४२, १; ४३, २; ४४, ९; ५४, १; ५९, १; २^{२}; ३^{२}; ४^{२}; ५; ८; ६१, २७; ७५, १; ७७, ४; ९४, १४; १००, २; १०१, ११; ११२, ९; ११३, १०; १२०, ३; १२६, ६; १३२, ५; १३३, १; ३; ७; १७८, १; १७९, २.

सुऽअग्नर्यः १. २६, ७; ८^{२}; ७. १५, ८; ८. १९, ७; ६०, ६.

सुऽअंगः १०. १, १.

सुऽअंगा ३. ४३, ४.

सुऽअंगुरिः २. ३२, ७; ४. ५४, ४.

सुऽअंगुरे १०. ८६, ८.

सुऽअंचः ४. ६, ९; ७. ५६, १६; ९. ७३, ७.

सुऽअंचं ६. १५, १०; ५८, ४; ७. १०, ३.

सुऽअंचाः ५. ३७, १.

सुऽअध्वर १. ४४, ८; ५. २८, ५; ८. २३, ५.

सऽअध्वरः १. १२७, १; २. २, ८; ८. १९, ५; २४; १०३, १२; १३; ९. ३, ८; ८६, ७; १०. ११, ५; ११५, २.

सुऽअध्वरं १. ४५, १; ३. २, ८; ९, ८; ४. ४६, ४; ५. ९, ३; ६. १५, ४; १६, ४०; ७. १६, १; ८. ५, ३३; ४०, ११.

सुऽअध्वरा ३. ६, ६; २९, १२; ६. १०, १; ७. १७, ३; ४.

सुऽअध्वरासः ४. ४५, ५.

सुऽअध्वरे १. १४२, ५; ५. १७, १; ८. ४४, १३.

सुऽअनीक २. १, ८; ४. ६, ६; ६. १५, १६; ७. १, २३; ३, ६.

सुऽअपत्यं १. ११६, १९; २. ४, ८; ७. १, ५; १२.

सुऽअपत्यस्य २. २, १२; ९, ५; ३. १६, १; १९, ३; १०. ३०, १२.

सुऽअपत्यानि १. ७२, ९; ४. ३४, ९; ७. ९१, ३; ८. १५, १०.

सुऽअपत्याय १. ८३, ६; ४. २, ११.

सुऽअपत्ये ३. ३, ७.

सुऽअपत्यै १. ५४, ११.

सुऽअपसः १. १५९, ३; १६१, ६; ४. २, १९; ३३, ८; १०. ७६, ८; ११०, ८.

सुऽअपस्यते १०. ११, ६.

सुऽअपस्यमानः १. ६२, ९.

सुऽअपस्यया १. ५२, ३; ११०, ८; १६१, ११; ३. ३, ११; ४. ३५, २; १०. ११३, ४.

सुऽअपस्या ४. ३५, ९.

सुऽअपाः १. ८५, ९; १३०, ६; ४. ५६, ३; ५. २, ११; २९, १५; ६०, ५; ७. ८८, ४; ९. ६६, २१.

सुऽअपाक ४. ३, २.

सुऽअपिवात ७. ४६, ३.

सुऽअभसः १०. ६३, ३; ७८, १.

सुऽअभिष्टयः १. १७३, ९.

सुऽअभिष्टि ७. १०१, २.

सुऽअभिष्टिः ६. ३३, १.

सुऽअभिष्टिं १. ५१, २; ८. १९, ३२.

सुऽअभीशुः ८. ६८, १८.

सुऽअभीशून् ८. ६८, १६.

सुऽअरंकृतेन १. १६२, ५.

सुऽअरिः १. ६१, ९.

सुऽअरित्रां १०. ६३, १०.

सुऽअर्काः ७. ३५, ९; ३८, ७.

सुऽअर्कैः १. ८८, १.

सुऽअर्चिः २. ३, २.

सुऽअर्थे १. १४१, ११.

सुऽअवसः ४. ३३, ८; ६. ५१, ११.

सुऽअवसं ५. ८, २; ६०, १; १०. ४७, २.

सुऽअवसा १. ९३, ७.

सुऽअश्वः १. ८४, ६; ११७, २; १२५, २; ४. २, ४; ४, १०; २९, २; ४५, ७; ५. ३३, ३; ६. ३३, १.

सुऽअश्वा ७. ६८, १; ६९, ३; १०. ७५, ८.

सुऽअश्वाः ४. ४, ८; ४२, ५; ५. ५७, २; ७. ५६, १.

सुऽअश्वासः ५. ६५, ३.

सुऽअश्व्यं १. ४०, २; ९३, २; १६२, २२; १८०, ९; २. १, ५; ३. २६, ३; ५५, १८; ८. १२, ३३; २६, २३; ९. ६५, १७.

सुऽअश्व्या १०. ११३, १०.

सुऽअष्ट्रान् १०. ४२, ५.

सुऽआततः ९. ७४, २.

सुऽआततं ८. ७७, ६.

सुऽआधीः १. ६७, १; ७०, २; ४. ३, ४; ५. ८२, ८; १०. ४५, १.

सुऽआधीभिः ५. १४, ६; ६. ३२, २.

सुऽआध्यः १. १६, ९; ७२, ८; १५१, १; २. २८, २; ३. ८, ४; ६. १६, ७; ७. २, ५; ८. १९, १७; ४८, १; ९. ३१, १; ६५, ४; ८६, २४; १०१, १०; १०. ६१, ७; ७८, १.

सुऽआध्यं १. ७१, ८.

सुऽआपे ८. ५३, ५.

सुऽआभुवः १. १५१, २; ४. ५०, १०; ७. ३०, ४; १०. २१, २.

सुऽआभुवं ५. ६, ३; ९. १२, ९.

सुऽआभुवा १०. १२२, ३.

सुऽआयसं १०. ५३, ९.

सुऽआयुजः १. ९२, २.

सुऽआयुध ९. ४, ७; ६५, ५.

सुऽआयुधः ९. ८६, १२; ८७, २; ९६, १६; १०८, १५; ११०, १२.

सुऽआयुधं ६. १७, १३; ९. १५, ८; १०. ४७, २.

सुऽआयुधस्य ९. ३१, ६.

सुऽआयुधाः ५. ५७, २.

सुऽआयुधासः ५. ८७, ५; ७. ५६, ११.

सुऽआवेशः ७. ५४, १; ९७, ७.

सुऽआवेशा १०. ६३, १६.

सुऽआशितः १०. २८, १.

सुऽआशिषं १०. ४४, ५.

सुऽआसः १०. ३, ४.

सुऽआसं ४. ६, ८.

सुऽआहुत ७. १६, ७.

सुऽआहुतः १. ४४, ६; ३. २७, ५; ७. १६, २; ८. ३९, ६; १०. ११८, १.

सुऽआहुतं १. ४४, ४; ७. १२, १.

सुऽइध्मा १. १२१, ७.

सुऽइषुः ५. ४२, ११.

सुऽइष्टेन १. १६२, ५.

सुऽउक्तं ७. ५८, ६; १०. ६५, १४.

सुऽउक्तस्य २. २३, १९; २४, १६.

सुऽउक्तानि १. ९३, १; ८. ४४, २.

सुऽउक्ताय ९. ९, ८; ९०, ६; ९१, ५.

सुऽउक्तेन १. १७१, १; २. ६, २; १८, ३; ६. ५२, १७.

सुऽउक्तेभिः १. ३६, १; ५. ४५, ४.

सुऽउक्तैः १. ४२, १०; ७०, ३; ५. ४९, २; ८२, ७; ७. २९, ३; ६५, १; ६६, १२; ६८, ९; १०. ६१, २६.

सुऽउपवंचना १०. १८, ११.

सुऽउपस्थाभिः ९. ६१, २१.

सुऽउपायनः १. १, ९.

सुऽउपायना १०. १८, ११.

सुऽऊतयः ८. ४७, १.

सुऽओजः ६. २२, ६.

सुऽओजाः ७. २०, ३; १०. २९, ८.

सुऽकरं ८. ८०, ६.

सुकर्मऽभिः ९. ७०, ४; ८; ९९, ७.

सुऽकर्मा ४. ३३, ९.

सुऽकर्माणः ४. २, १७.

सुऽकिंशुकं १०. ८५, २०.

सुऽकीर्तयः ८. ४५, ३३.

सुऽकीर्तिः १. ६०, ३; १८६, ३; ५. १०, ४.

सुऽकीर्ति २. २८, १.

सुऽकीर्त्या ८. २६, १९.

सुऽकृत ३. ५४, १२; ४. २५, ५.

सुऽकृतः ६. १९, १; ७. ६२, १.

सुऽकृतः १. ४८, ११; ११७, २; १४७, ३; १८३, १; ३. ३१, १२; ३८, २; ६०, ३; ४. १३, १; ५. ४, ८; ७. ३५, १२; १०. १७, ४; ७; ९४, २.

सुऽकृतं १. ८५, ९; १२५, ३; ८. ७७, ११; ९. ७०, ७; ७४, ३; १०. १५, १३; ३४, ११; ४४, ९; १००, ६.

सुऽकृतं ९. ७३, १; १०. ६३, ९.

सुऽकृतस्य ३. २९, ८; १०. ६१, ६; ७१, ६; ८५, २४; ९५, १७.

सुऽकृता ३. ३०, १३; ३२, ८; ३४, ६; ४. २१, ९; ५. २९, १५; ६. ४१, २; १०. ७५, ८.

सुऽकृता १. १६२, १०.

सुऽकृताः १. ३५, ११; १३४, २.

सुऽकृतानि ३. ६०, ४; ७. ३५, ४.

सुऽकृतां ७. ३५, ४; १०. १६, ४.

सुऽकृते १. ३१, ४; ४७, ८; ९२, ३; १२८, ६; १५६, ५; १६६, १२; १८२, १; ३. ३१, ७; ५. ४, ११; ६२, ६; ६. ७०, २; ७. ७९, ३; १०. १२२, ३.

सुऽकृतौ ३. ३१, २.

सुकृत्ऽतमाः ९. ८३, ४.

सुकृत्ऽतरः १. ३१, ४; १५६, ५.

सुकृत्ऽतराय ८. ४६, २७.

सुऽकृत्यया १. २०, ८; ८३, ४; ३. ६०, ३; ४. ३५, २; ८. ५४, २; ९. ४७, १; ४८, १; १०. ९४, २.

सुऽकृत्या ४. ३५, ७.

सुऽकृत्वनि ८. ४६, २७.

सुऽकृत्वने ८. १३, ७.

सुकृत्ऽसु ७. ९, १.

सुऽकेतवः ३. ७, १०.

सुऽक्रतवः ७. २, २.

सुऽक्रतुः १. २५, १०; १२; ५५, ६; ९१, २; १२८, ४; १२९, १०; १४१, ११; २. ३१, ३; ३. ३, ७; ५. ११, २; २५, ९; ६५, १; ६. ७, ७; ८, २; ३०, २; ७१, १; ७. ३, ९; ९, २; ८५, ४; ८. २५, २; ३३, ५; १३; ४६, २७; ९६, १९; ९. २, ३; १२, ४; ७०, ६; ७३, ८; १०२, ३; १०. २५, ८; ४९, ९; ९१, ३.

सुऽक्रतुं १. १२, १; ३. ४९, १; ६. ४८, १४; ७. ३६, ४; ८. १९, ३; १७; ८४, ८.

सुक्रतुऽयया १. १६०, ४.

सुक्रतुऽयसे १०. १२२, ७.

सुक्रतुऽया १. ३१, ३.

सुक्रतू इति सुऽक्रतू ५. ६६, १; ८. २५, ५; ८.

सुक्रतू इति सुऽक्रतू ३. ६२, १६; ७. ६१, २.

सुक्रतो इति सुऽक्रतो १. १४४, ७; ८. ७४, ७.

सुक्रतो इति सुऽक्रतो १. ५, ६; ५१, १३; ३. १, २२; ४. ४, ११; ५. २०, ४; ४४, २; ६. १६, ३; २९; ३०, ३; ७. ११, ६; ८. १, १८; ५४, ६; ९. ४८, ३; ६३, २८; ६५, ३०; ७२, ८; १०. ७०, १; १२२, २; ६; १४४, ६.

सुऽक्षत्र ५. ३२, ५; ३८, १; ७. ८९, १.

सुऽक्षत्रः ३. ५९, ४; ७. ६४, १.

सुऽक्षत्रं १. ११६, १९.

सुऽक्षत्रान् ६. ५१, ४.

सुऽक्षत्रासः १. १९, ५; ६. ४९, १; ५१, १०.

सुऽक्षयं १०. २३, ४.

सुऽक्षितयः ८. ४३, १८; २९.

सुऽक्षितये ७. ५६, २४.

सुऽक्षितिं १. ४०, ८; ९१, २१; २. १९, ८; ३५, १५; ६. २, ११; ७. ७४, ६; १०. २०, १०.

सुऽक्षितीः ५. ६, ८; ७. ६४, ४; ८. ८४, ६.

सुऽक्षितीनां ९. १०८, १३.

सुऽक्षेत्रा १. १२२, ६; ४. ३३, ७.

सुऽक्षेत्रिया १. ९७, २.

सुऽखः १. १२०, ११.
सुखऽस्तमे १. १३, ४; १६, २.
सुऽखं १. २०, ३; ४९, २; ३. ३५, ४; ५. ६३, ५; ८. ५८, ३; ९. ११२, ४; १०. ७५, ९.
सुखऽरथं ५. ३०, १.
सुऽखादयः १. ८७, ६.
सुऽखादये ५. ८७, १.
सुऽखे ३. ४१, ९.
सुऽखेषु ५. ६०, २.
सुऽखैः ५. ५, ३.
सुऽगः १. ४१, ४; २. २७, ६; ३. ५४, २१; ७. ४२, २.
सुऽगंधिनां ८. १९, २४.
सुगंधिं ७. ५९, १२.
सुऽगभस्तयः ९. ७२, २.
सुऽगभस्तिः ५. ४३, ४.
सुऽगभस्ति ६. ४९, ९.
सुऽगं १. ४३, ६; ९४, ९; ११; १०२, ४; १०६, ५; २. २३, ७; ५. ५४, ३; ६. ४४, १८; ५१, १३; १५; ७. १०४, ७; ८. ४७, ११; ९३, १०; १०. ८६, ५.
सुऽगवः १. ११६, २५.
सुऽगव्यं १. १६२, २२; ८. १२, ३३.
सुऽगा १. ४२, ७; ६. ६४, ४; ७. ६२, ६; ९. ६२, २; १०. ६३, ७.
सुऽगाः १. १६५, ८; ८. ३१, १३.
सुगातुऽया १. ९७, २.
सुऽगाधा ७. ९७, ८.
सुऽगान् ३. ३०, १०; ५. ८०, २; १०. ५१, ५.
सुऽगानि ६. ६४, १; ९. ९७, १६.
सुऽगार्हपत्याः ५. ४, २.
सुऽगुः १. १२५, २.
सुऽगेभिः १. ३५, ११; ११६, २०; १६२, २१; १६३, ६; २. २७, ७; ८. २७, १७; १०. ८५, ३२; ११३, १०.
सुगेऽवृधः ८. १८, २.
सुऽगेषु ६. २१, १२.
सुऽगोपा १. १२०, ७.
सुऽगोपाः २. २३, ५; ३. ४५, ३; ५. ३८, ५²; ४४, २; ६. ५१, ११; १०. १०८, ७.
सुऽगोपातमः १. ८६, १.
सुग्म्यः १. १७३, ४.
सुग्म्यं १. ४८, १३; ८. २२, १५.
सुग्म्याय ८. २२, १५.
सुऽग्रथितं १. १२१, १०.
सुऽघ्नाय ८. ७०, ११.
सुऽचक्रं १०. ८५, २०.
सुऽचक्रे ६. ३७, ३.
सुऽचक्षसः १०. ३७, ७.
सुऽचंद्र ५. ६, ५.
सुऽचंद्र १. ७४, ६; ५. ६, ९.
सुऽचंद्रं २. ३४, १३; ४. २, १९.
सुऽचेतसः ४. ३६, २.
सुऽचेतसं ७. ३, १०; ६०, ६.
सुऽचेतुना ९. ६५, ३०.
सुऽचेतुना १. ७९, ९; १२७, ११²; १५९, ५; १६६, ६; ५. ५१, ११; ६४, २; ६५, ३.
सुच्छर्दिःऽतमे ७. ६६, १३.
सुऽजनिमा ७. १००, ४; १०. २, ७; १८, ६.
सुऽजनिमानः ७. ६२, ४.
सुजन्मनी इति सुऽजन्मनी १. १६०, १.
सुऽजंभः ८. ६०, १३.
सुऽजात ५. २१, २; ८. ७४, ७.
सुऽजात २. १, १५; ३. १५, २; ७. ८, ५; १०. ७, २; ६; ५१, ७.
सुऽजातः ७. ६४, १; १०. ७९, ७; ९५, १०; ९९, ७.
सुऽजाततां १०. १७२, ४.
सुऽजातं १. ६५, २; ३. २३, ३; १०. ५, ४.
सुऽजातं ७. ५६, २१.
सुऽजाता ५. ५६, ९.
सुऽजाताः १. ११८, १०; ८. २५, २.
सुऽजाताः १. ७२, ३.
सुऽजाताः २. २, ११; ७. १, ४.
सुऽजाताः १. ८८, ३; १६६, १२.
सुऽजातान् ६. ५१, ३.
सुऽजाताय ५. ५३, १२.
सुऽजातासः ५. ६, २; ५७, ५; ५९, ६; ७. १, १५; ८. २०, ८.
सुऽजाते ५. ७९, १.
सुऽजाते १. १२३, ३; ७. ७६, ६; ७७, ६.
सुऽजिह्व १. १४, ७; १४२, ४; १०. ११०, २.
सुऽजिह्वः ३. ५४, ११.
सुऽजिह्वं ७. ४५, ४.
सुऽजिह्वाः १. १६६, ११.
सुऽजिह्वौ १. १३, ८.
सुऽजुष्टा ६. ६१, १०.
सुऽजूर्णिः ४. ६, ३; १०. ९५, ६.
सुऽज्योतिषः ३. २०, १; ६. ५०, २.
सुऽज्योतिषः १०. ८९, १५.
सुतः १. ४७, १; ८०, २; ८६, ४; १०४, ९; १३७, २; ३²; १७७, ३; २. ११, ११; १८, ४; ३६, ५; ४१, ४; ३. ३५, ७; ४४, १; ४. ४६, ६; ५. ४०, २; ५१, ४; ६. २९, ४; ४०, १; ४१, ४; ४३, १; ४४, १; ७. २४, २; ८. २, २; १७, १२; २२, ८; ६६, १५; ८२, ५; ७; ९४, ४; १००, ३; ९. १, १; ३, ९; १०; ६, ७; ८; २४, ५; २७, ३; २८, २; ३४, २; ३६, १; ३७, १; ७; ३८, ६; ३९, ३; ५; ४०, २; ४१, ४; ४२, २; ६; ४४, ३; ५१, ४; ५; ६१, ८; २८; ६२, ५; १६; १९; ६३, ३; १३; ६६, ७; ६७, २; १२; १५; ६८, ९; ७१, ३; ७२, ५; ७५, ४; ८०, ४; ८४, ३; ८६, २३; ३४; ३५; ९७, १; ३५; ४५; ९९, ७; ८; १००, ५, ६; १०१, २; १०३, ६; १०५, ३; ४; १०६, २; १०७, १७; १०८, ५; १०; १०९, १८; ११३, २; १०. ११२, ५; ११६, ७; १४४, ६.
सुतऽक्रे ६. ३१, ४.
सुतऽपाः १. १५५, २; ४. २५, ७; ६. २४, १; ८. २, ४; १०. १००, १.
सुतऽपाः ६. २३, ६.
सुतऽपावन् ६. २४, ९.
सुतऽपाव्नः ८. २, ७.

सुतऽपात्रे १. ५, ५.

सुतऽपेयाय ४. ४४, ३.

सुतऽपौ ६. ६८, १०.

सुतं १. ३, ७; ८; १०, ११; १६, ४; ५; ७; ८; २१, ४; ८४, ४; १२५, ३; २. २२, १; ३. १२, १; २; २२, १; ४०, २; ५; ६; ४२, २; ७; ४४, ५; ४७, ३; ५१, ८—१०; ६०, ५; ४. २५, ७; ४६, १; ५. २९, ७; ४०, १; ६४, ७; ७१, ३; ६. २३, ३; ४२, ४; ५७, २; ६०, ७; ६८, १०; ८. २, १; २६; ४, ४; ६, ३६; ८, ३; ३२, २१; ३३, २; ३५, ७; ३८, ४; ४५, २२; २६; ४६, ७; ५१, १; ५२, १; ६५, ५; ६६, ७; ७६, ९; १०; ९२, १९; ९३, ३१; ९५, ३; ९. ६, ६; ११, ५; ५१, १; ६३, १०; ६८, ७; १०७, १; ११०, २; १०. २४, १; २७, २; १०५, १.

सुतं १. २८, ८.

सुतंऽभरः ५. ४४, १३.

सुऽतरणान् ४. १९, ६.

सुऽतरा ७. ९७, ८; १०. १२७, ६.

सुऽतराः ६. ६०, ११.

सुऽतर्माणं ८. ४२, ३.

सुतऽवंतः १. ३, ५; ३. २५, ४; ५८, ९; ८. १७, ४; १०. १७१, १.

सुतऽवंतां १०. १००, ११.

सुतऽवंतः ८. १७, ३; २६, २२; ३३, १; ५१, ६; ६१, १४; ६५, ६; ९३, ३०.

सुतऽवान् १. ८४, ९; ८. ९७, ४.

सुऽतष्टः ७. ३४, १.

सुऽतष्टं २. ३५, २.

सुतऽसोमः १. १६७, ६; ३. ३२, १२; ४. २५, १; ५. ३७, २; ५; १०. २८, २.

सुतऽसोमं ५. ३०, १; ३१, १२; ७. ९८, १.

सुतसोमवत्ऽभिः १०. ६९, ११.

सुतऽसोमस्य २. १२, ६.

सुतऽसोमाः १. २, २; ४५, ८; ४७, ४.

सुतऽसोमाय १. १४२, १; ४. २, १३.

सुतऽसोमासः १. ४४, ८; ५. २९, १२; ८. २७, ७.

सुतऽसोमे ५. ६१, १८; ८. ६६, १.

सुतऽसोमेषु १. ५१, १२.

सुतस्य १. ५, ६; ३२, ३; ५२, १०; ५६, ६; १०८, १; ५—१३; १०९, ५; २. ११, १०; १७; १५, १; ३. ३५, १०; ४२, ९; ४३, ५; ४८, १; ५१, ७; ४. १८, ३; २५, ३; ४६, २; ४८, १; ५. २९, २; ३२, ६; ५१, १; ५; ७. ४८, १; ९०, १; ८. १, २६; ३, १; ८; १३, १४; २२, २४; २५, २४; ४८, ७; ६१, ३; ८२, ६; ८७, १; ९२, ३०; ९४, ६; ९. २, ३; १६, ७; २४, ७; २९, १; ५८, १; १००, ४; १०९, २; १५; १११, १; १०. १५, ३; ५०, ७; ९४, ८; १०४, १—३; ६; ११२, १; ११४, ७; ११६, २; ४; १६७, १.

सुताः १. २, ४; ३, २; ४; ५, ५; २३, १; ८४, ५; १३५, ६; १३९, ६; १६८, ३; ३. ४०, ४; ५. ५१, ७; ८. ५०, २; ७६, ८; ९३, २२; २५; ९. १०, ४; १२, १; ३२, १; ३३, ३; ४६, ३; ६३, ६; १५; ६९, ९; ८१, १; १०६, १; १०. १६०, २.

सुतात् ७. ३३, २.

सुतान् ५. ७८, १; ८. ६, ४२; १०. १६७, २.

सुतानां १. २, ५; १३४, ६; १३५, ५; ३. ४७, १; ५. ५१, ६; ६. ४४, १३; २०; ८. ३२, १९; ३४, ५; ६४, ३; १०. ९६, १३.

सुताय ९. १०१, १.

सुतासः १. १६, ६; ८२, ६; १३५, १; १३७, २; १३९, ६; १६५, ४; २. ११, ११; ३. ३६, ३; ४६, ४; ४. ३७, २; ५. ३०, १३; ६. ४१, १; ७. २६, १; २; ९०, १; ८. २, ७; १०; ६, २१; १३, १६; ४९, ३; ५०, ३; ८२, २; ९५, २; ९. ६७, १८; ८८, ६; १०१, ४; १०. २९, ६; १६०, १.

सुतासः ९. १०६, ९.

सुऽतीर्थं ८. ४७, ११.

सुऽतीर्था ४. २९, ३.

सुऽतुकः १. १४९, ५; १०. ३, ७.

सुऽतुका ६. २२, १०.

सुऽतुकाः १. १७८, २.

सुऽतुकान् ७. १८, ९; १०. ४२, ५.

सुऽतुकेभिः १०. ३, ७.

सुते १. ३, ६; ५, २; ९, २; १६, ४; ८१, ८; १०५, ७; १३०, १; १६१, ५; १७७, २; ३. ४०, १; ५१, ११; ५३, १०; ६०, ४; ४. ४९, ५; ५. ३०, ३; ५१, ८; ६. २३, १; ५; ६; १०; ४०, ३; ४५, २२; ५९, ३; ७. २६, ५; ३२, २; ४२, २; ५९, ३; ६७, ४; ९४, १०; ८. १, १; १२, १७; १३, ९; २१, १५; ३२, ६; ३३, २; ४; ७; ८; ४५, २२; ३८; ६१, ११; ६४, ६; ७२, १३; ९२, २०; ९३, २०; ९७, ८; ९. १०७, २; १०. २३, ४; ४४, ९; ५०, ७; ९४, १४; १६७, ४.

सुतेऽकरासः १०. ७१, ९.

सुतेऽगृभे ५. ४४, ५.

सुतेन ७. ३३, २.

सुतेभिः ३. ३५, ५; ४. ४१, ३; ६. ४२, २; ३.

सुतेऽरणं १०. १०४, ७.

सुतेषु १. १०, ५; ४. ३२, ११; ६. २३, ९; ४१, ५; ५९, १; ४; ७. २६, ३; ८. १३, १; ५४, २; ५९, १; ९२, २६; ९५, १; ९६, १९; ९७, ६; ९९, २; ९. ६५, २७.

सुतेऽसुते १. ९, १०; ३. ३६, १; ६. ४५, २८.

सुऽत्यजे ८. ६०, १६.

सुऽत्रात्रः ६. ६८, ७.

सुऽत्रात्रा ५. ७०, ३.

सुऽत्रात्रासः ६. ५१, ११.

सुऽत्रामा ६. ४७, १२; १३.
सुऽत्रामाणं १०. ६३, १०.
सुत्वा १०. ९९, ११.
सुऽदंससः १. ८५, १; १५९, ३.
सुऽदंससं २. २, ३; १०. ६६, ४.
सुऽदंससा १. ९२, ८; १५९, १; ६. ७०, ६; ८. १०, ३.
सुऽदंसाः १. ६२, ७; ९; ३. ३२, ८; ६१, ४.
सुऽदक्ष १. १०१, ९; ९. १०५, ४; १०८, १०.
सुऽदक्षः १. ९१, २; २. ९, १; ३. ४, ९; ५. ११, १; ६. ७१, १; ९. ८७, २; १०. ९१, ३.
सुऽदक्षं ३. २३, २; ४. १६, १; ६. १९, ८; ७. १, ६; २, ३; ८. १९, १३; १०. ४७, ४.
सुऽदक्षस्य ८. ९२, ४.
सुऽदक्षा ७. ६६, २.
सुऽदक्षा ३. ५८, ७.
सुऽदाक्षिणः ८. ३३, ५.
सुऽदक्षिणं ७. ३२, ३.
सुऽदत्र ७. ८, ३.
सुऽदत्रः १. १६४, ४९; ७. ३४, २२.
सुदर्शऽतरः १. १२७, ५.
सुऽदशः ४. २३, ६; ५. ३, ४.
सुऽदाः ८. ७८, ४.
सुदाःऽतराय १. १८४, १; १८५, ९.
सुऽदातु ८. ७८, ८.
सुऽदानवः १०. ६६, १२.
सुऽदानवः १. ४०, १; ४४, १४; ६४, ६; ८५, १०; १४१, ९; २. ३४, ८; ३. २६, ५; ५. ५२, ५; ५३, ६; ५७, ५; ६७, ४; ६. १६, ८; ७. ९६, ४; ८. २०, १८; १०३, ७; ९. ७४, ४; १०. ६५, ११; ७८, ५; १७२, ३.
सुऽदानवः १. १५, २; २३, ९; ३९, १०; ४५, १०; १०६, १–६; १७२, १–३; ६. ५१, १५; ७. ५९, १०; ६६, ५; ८. ७, १९; २०; १८, १२; १९, ३४; २०, २३; २५, ११; ६७, १६; ८३, ६; ८; ९.

सुऽदानवे १. ४७, ८; ९२, ३; ६. २, ४; ७. ३१, २; ८. २५, १२; १०. २३, ६.
सुऽदानुः ३. २९, ७; ४. ४, ७; ५. ४१, १८; ६. ३८, १; ६६, ५; ६८, ५.
सुदानुऽभिः १०. १७२, २.
सुऽदानु ३. २६, १; ८. ८८, २.
सुदानू इति सुऽदानू १. ११२, ११; ११७, १०; २४; १८०, ६; १८४, ४; ३. ५८, ७; ४. ४१, ८; ५. ६२, ९; ६. ६७, २; ७. ६१, ३.
सुऽदानून् ५. ४१, १६.
सुऽदामन् ६. २०, ७.
सुऽदामन् ६. २४, ४.
सुऽदाम्ने १. ७६, ३.
सुऽदासः ३. ५३, ११; ७. १८, २२; २३; २५; ३२, १०.
सुऽदासं ३. ५३, ९; ७. १८, ३; ३३, ३; ८३, १; ४; ६; ७.
सुऽदासे १. ४७, ६; ६३, ७; ११२, १९; ५. ५३, २; ७. १८, ५; ९; १५, १७; १९, ६; २०, २; २५, ३; ५३, ३; ६०, ८; ९; ६४, ३; ८३, ८.
सुदिनऽत्वं २. २१, ६.
सुदिनऽत्वे ३. ८, ५; २३, ४; ७. ८८, ४; १०. ७०, १.
सुऽदिना ४. ४, ७; ५. ६०, ५; ७. ११, २; १८, २१; ३०, ३.
सुदिनाऽइव १०. १०६, १.
सुऽदिनाः १. १२४, ९; ७. ९०, ४.
सुऽदिनानि ४. ४, ६.
सुऽदिने १. १८६, ९.
सुदिने इति सुऽदिने १०. ३९, १२.
सुऽदिनेषु ४. ३७, १.
सुऽदिवः १०. ३, ५.
सुऽदीतयः १. १५९, ४; ५. ४६, ६; ८. ९७, १२.
सुऽदीतये ८. ७१, १४.
सुदीतिऽभिः ५. ८, ४; २५, २; ६४, ५; ६. ४८, ३; ८. २०, २.
सुऽदीतिं ३. २, १३; १७, ४; २७, १०.

सुऽदीती ७. १, २१.
सुऽदीदितिं ३. ९, १; ८. १९, ४.
सुऽदुघा २. ३५, ७; ५. ६०, ५; १०. ४३, ९; ६९, ८.
सुदुघाऽइव १. १८६, ४; ७. २, ६.
सुऽदुघाः ४. १, १३; ५. ३१, ३; ८; ७. १८, १; ३६, ६; ४३, ४; ८. ६९, १०; ९. ७७, १; ९६, २४; ९७, ५०.
सुऽदुघां १. १६४, २६; ६. ३५, ४; ८. १, १०; १०. १२२, ६.
सुदुघाऽइव १. ४, १; ८. ५२, ४.
सुदुघे इति सुऽदुघे २. ३, ६.
सुऽदृशः ९. ७३, ७.
सुऽदृशं ३. १७, ४; ६. १५, १०.
सुऽदृशी १. १२२, २.
सुदृशीऽइव ४. १६, १५.
सुऽदृशीः ५. ४४, २.
सुऽदृशीकः ५. ४, २; ९. ८६, ४५.
सुऽदृशीकं ४. १६, ४; ७. ७७, ३.
सुदृशीकऽरूपः ४. ५, १५.
सुदृशीकऽसंदृक् ७. ७७, २.
सुऽदेवः १. ८४, १८; ५. ५३, १५; ८. ६९, १२; १०. ९५, १४.
सुऽदेवं १. ७४, ५.
सुऽदेवाः ८. ५५, ४.
सुऽदेवाय ८. ५, ६.
सुऽदेव्यं १. ११२, १९; १०. ३५, ४.
सुदोघे इति सुऽदोघे ३. १५, ६.
सुऽद्युतः १. १४३, ३; ८. २३, ४.
सुऽद्युते १. १४०, १.
सुऽद्युम्नां ३. १९, २.
सुऽद्योत्मा १. १४१, १२.
सुऽद्योत्मानं २. ४, १.
सुऽद्रविणः १. ९४, १५; १०. ६१, २१.
सुऽद्वै ७. ३२, २०; १०. २८, ८.
सुऽधनौ ५. ३४, ८.
सुऽधन्वा ५. ४२, ११.
सुऽधन्वानः ५. ५७, २.
सुऽधातु ७. ६०, ११.
सुऽधारः ९. १०९, ७.
सुऽधाराः ७. ३६, ६; ९. ९६, २४.
सुऽधितः ३. २३, १; २९, २; ४. ६, ३; ७; ५०, ८; ७. ४२, ४.

सुऽधितं १. १४०, ११; ४. २, १०; ५. ३, २; ६. १५, २; ७. ७, ३; ३२, १३; ८. २३, ८; ६९, १७; १०. २७, १६.
सुऽधिता १. १६७, ३; ३. ११, ८; ८. ६०, ४; १०. ७०, ८.
सुधिताऽइव १. १६६, ६.
सुऽधिताः १०. ११५, ७.
सुऽधितानि १. १३५, ४; २. २७, १०; ६. १५, १५; १०. ५३, २.
सुऽधितेभिः ६. ३३, ३.
सुऽधुरः १. ७३, १०; ३. ३८, १.
सुऽधुरं ८. ३, २२.
सुऽधुरां ३. ४३, ४; ५. २७, २; ४३, ५.
सुऽधृष्टमं १. १८, ९.
सुधृष्टमे इति सुऽधृष्टमे १. १६०, २.
सुऽध्यः १. ५१, १४; ४. २, १४; २१, ८; ५. ४५, ५; ६. १, ७.
सुनवंत् ४. २४, ७; ८. ३१, १.
सुनवाम ३. ५३, ४; ४. २५, ४; ५. ३७, १.
सुनवाम १. ९९, १; १०३, ६.
सुनवै ८. ९१, १[२].
सुनिःऽअजं १. १०, ७.
सुनिःऽमथा ३. २९, १२.
सुऽनिधा ३. २९, १२.
सुऽनिष्काः ४. ३७, ४; ७. ५६, ११.
सुऽनीतयः १०. ७८, २.
सुऽनीतिः ६. ४७, ७.
सुनीतिऽभिः २. २३, ४; १०. ६३, १३.
सुऽनीती ६. ४५, १; ८. ६०, ११.
सुऽनीथः १. ३५, ७; १०; २. ८, २; ८. ४६, ४.
सुऽनीथं १०. ४७, २.
सुऽनीथाः ३. ८, ८; ६. ५१, ११.
सुऽनीथाय १. ६२, १३.
सुऽनीथासः ५. ६७, ४.
सुऽनीथे ५. ७९, २.
सुनु १. २८, ६.
सुनुत १०. ३०, १५; १७५, १.
सुनुत १०. १४, १३.
सुनुतः ८. ३१, ५.
सुनुथ १०. ७६, ८.
सुनुध्वं ४. ३५, ४.
सुनोत ७. ३२, ८; ९. ३०, ६; ५१, २.
सुनोत २. ३०, ७; १०. ३०, ३.
सुनोतन ५. ३४, १.
सुनोतन १०. ७६, २; ४.
सुनोति १. १२२, ९; ४. २४, ६; ३५, ६; ५. ३४, ३; ७. ३२, ६; १०. ८६, १५; १६०, ३; ४.
सुनोति १. १०९, ४.
सुनोतु ८. ३३, १२.
सुन्वत् १०. २७, २२.
सुन्वतः १. २, ६; ४, १०; ३३, ७; ९४, ८; २. ४१, २; ५. ३४, ६; ६. ५४, ६; ६०, १५; ८. ३, १४; १२, १८; १३, ४; ३५, १६; १९; ३६, १; ७; ३७, १; ३८, ८; ६२, १२; ९८, ५.
सुन्वतां ८. ३२, १६.
सुन्वति ८. ९७, २.
सुन्वते १. २०, ७; ५१, १३; ८१, २; ८३, ३; ९२, ३; १३२, १; १४१, १०; २. १२, १५; १९, ५; ४. ३१, ८; ५. २६, ५; ६०, ७; ६. १६, ५; ३१, ४; ८. १, २२; ४, ४; १२, १२; १४, ३; १७, १०; ५०, १; ५९, १; ६६, २; ६; ६७, ६; १००, ६; १०. २७, १; ४२, ८; ४३, ८; ७६, ८; १००, ३; १२५, २; १३४, ४; १७५, ४.
सुन्वत्ऽभ्यः १. १३२, ४.
सुन्वन् १. १३३, ७; ६. २०, १३.
सुन्वंतः ८. ४, १३; १३, ५; १०. ४८, ५.
सुन्वंतं २. १२, १४; ३०, ७; ८. २, १८; ९. ११२, १.
सुन्वंति ३. ३०, १; ५. ३०, ६; ९. ३४, ३; १०. २८, ३; ७६, ७.
सुन्वंतु ८. ५३, ४.
सुन्वान ८. ३१, १६.
सुन्वानः १. १३३, ७[२].
सुन्वानस्य ८. ८०, ३; ९. १०१, १३.
सुन्वानाय १. १३३, ७.
सुन्विरे ८. ५३, ३; ९३, ६.
सुन्विरे ७. ३२, ४.
सुन्वे ७. ९७, १.
सुन्वे ७. २९, १; ९. १०८, १३.
सुपत्नी इति सुऽपत्नी ६. ३, ७.
सुऽपत्नीः ६. ४४, २३; १०. १८, ७.
सुऽपथा १. २५, १२; ४२, ७; १८९, १; ६. ६४, १; ४; ७. ६०, ६; ८. ९७, १३; ९. ९७, १६; १०. ४४, २; ६३, ७.
सुऽपथानि ७. ६२, ६; ९. ८६, २६.
सुऽपर्दी ३. ३१, ६.
सुऽपसनि १. १८२, ५.
सुऽपर्णः १. ३५, ७; १०५, १; १६४, ४६; २. ४२, २; ४. २६, ४; ५. ४७, ३; ८. १००, ८; ९. ४८, ३; ७१, ९; ८६, २४; ९७, ३३; १०. २८, १०; ३०, २; ५५, ६; ११४, ४; १४४, ४; १४९, ३.
सुऽपर्णं १. १६४, ५२; ६. ७५, ११; ९. ८५, ११; १०. ११४, ५; १२३, ६.
सुपर्णऽयातुं ७. १०४, २२.
सुऽपर्णा १. १६४, २०; ४. ४३, ३; १०. ११४, ३.
सुऽपर्णाः १. ७९, २; १०५, ११; १६४, २१; २२; ४७; ९. ८६, १; १०. ७३, ११; ९४, ५.
सुऽपर्ण्यः ९. ८६, ३७; १०. ८८, १९.
सुऽपलाशं १०. ४३, ४.
सुऽपलाशे १०. १३५, १.
सुऽपाणिः ३. ३३, ६; ५४, १२; ७. ३४, २०.
सुऽपाणिं ६. ४९, ९; ७. ४५, ४.
सुपाणी इति सुऽपाणी १. ७१, ९.
सुपाणी इति सुऽपाणी १. १०९, ४.
सुऽपारः १. ४, १०; ६. ४७, ७; ८. १३, २.
सुपारऽक्षत्रः ७. ८७, ६.
सुऽपारं ३. ५०, ३.
सुऽपारा १. १५२, ७; ७. १८, ५.
सुऽपाराः ३. ३३, ९; ८. ९६, १.
सुऽपारासः ३. ३९, ८.
सुऽपित्र्य १०. ११५, ६.

सुऽपिप्पलाः ७. १०१, ५.
सुऽपिशः १. ६४, ८.
सुऽपीवसः १०. ९४, ११.
सुऽपुत्रा ३. ४, ११; १०. ८५, २५.
सुऽपुत्रां १०. ८५, ४५.
सुऽपुत्रे १०. ८६, १३.
सुऽपूतं ४. ५७, २; ५. १२, १; ७. ४, १; १०. ३०, ३.
सुऽपूर्णं ८. २, १.
सुऽपूर्णस्य ६. ४८, १८.
सुऽपूर्णाः ८. २, ८.
सुऽपृक्षः ७. ३७, ७.
सुऽपेशसः २. ३२, ५; ३५, १; ५. ५७, ४; ८. ६८, १६; ९. ५, ८; ८१, १.
सुऽपेशसं १. ४८, १३; ४९, २; ६३, ९; २. ३४, १३; ५. ३०, १३; ७. ३२, १३; ९. ७९, ५.
सुऽपेशसा १. १३, ७; ४७, २; १४२, ७; १८८, ६; ६. ७०, १; १०. ३६, १.
सुऽपेशाः १०. २७, १२; ११४, ३.
सुप्रऽअयनतमं ६. ६३, ३.
सुप्रऽअयनाः २. ३, ५; ५. ५, ५; १०. ११०, ५.
सुप्रऽअवीः १. ८३, १; २. २६, १; ४. २५, ५; ७. ६६, ५.
सुप्रऽअव्यः २. १३, ९; ४. २५, ६.
सुप्रऽअव्यं १. ६०, १.
सुप्रऽअव्ये १. ३४, ४; १०. १२५, २.
सुऽप्रकेतः ९. १०८, २.
सुऽप्रकेतं ४. ५०, २; १०. ३६, ५.
सुऽप्रकेतेभिः १. १७१, ६.
सुऽप्रकेतैः १०. ३, ३.
सुऽप्रचेतसः १. १५९, ४.
सुऽप्रजाः ४. ५०, ६; ९. ११४, १.
सुप्रजाःऽस्त्वं १०. ६२, ३.
सुऽप्रजां ४. ५३, ७.
सुऽप्रजावतीं १. १११, २.
सुऽप्रतिचक्षं ७. १, २.
सुऽप्रतीकः १. ९४, ७.
सुऽप्रतीकं ३. २९, ५; ६. १५, १०; २८, ६; ७. १०, ३; ६१, १.
सुऽप्रतीकस्य १. १४३, ३.
सुऽप्रतीका १. ९२, ६; ६. ७१, ५.
सुप्रतीके इति सुऽप्रतीके १. १८५, ६; ५. ५, ६.
सुऽप्रतूः ८. २३, २९.
सुऽप्रतूर्ति १. ४०, ४; ३. ९, १.
सुप्रतूर्ती इति सुऽप्रतूर्ती १. १८५, ७.
सुऽप्रनीतयः ८. २७, १२; १०. १५, ११; १२६, ४.
सुऽप्रनीतिः १. ७३, १; ४. २, १३.
सुऽप्रनीतिं १०. ६३, १०.
सुऽप्रनीती ५. ४२, १८.
सुऽप्रनीते ३. १, १६; १५, ४.
सुऽप्रपानं ५. ८३, ८; १०. ४०, १३.
सुऽप्रपाने ६. २८, ७.
सुऽप्रयसे २. २, १; ४, १; ६. ११, ४.
सुऽप्रयसा ४. ४१, ३.
सुऽप्रयाः ७. ३९, २.
सुप्रयावऽभिः ५. ४४, १२.
सुऽप्रवाचनं १. १०५, १२; २. १३, ११; ४. ३६, ३; १०. ३५, १२.
सुऽप्रवाचनाः १. १०६, ३.
सुऽप्राङ् १. १६२, २.
सुऽप्रावर्गं ८. २२, १८.
सुऽप्रीतः ५. २१, २; ६. १५, २; ७. ४२, ४; ८. २३, १३.
सुऽप्रैतुः १. १९०, ६.
सुप्सरःऽतमं ८. २६, २४.
सुऽफला ४. ५७, ६.
सुऽबद्धां १०. ८५, २५.
सुऽबंधवः १. १२६, ५.
सुऽबंधवे १०. ५९, ८.
सुऽबंधुः ३. १, ३; ६. ५८, ४; १०. ६१, २६.
सुऽबंधु १. १६२, ७.
सुबंधो इति सुऽबंधो १०. ६०, ७.
सुऽबंधोः १०. ६०, १०.
सुऽबर्हिषः ८. २०, २५.
सुऽबर्हिषं १. ७४, ५.
सुऽबाहुः २. ३२, ७; ८. १७, ८.
सुबाहो इति सुऽबाहो १०. ८६, ८.
सुऽब्रह्मण्यं १०. ६२, ४.
सुऽब्रह्मा ७. १६, २.
सुऽब्रह्माणं १०. ४७, ३.
सुऽभग ३. १६, ६; ५. ८, ३; ६. १३, १; ८. १९, ९; १८; १९.
सुऽभगः १. ८६, ७; १८१, ४; २. २५, ५; २६, २; २७, १५; ४. ४, ७; ५. ३७, ४; ७. ६३, १; ८. १९, १४; २०, १५.
सुभगऽत्वं २. २१, ६.
सुऽभगं ३. १, ४; ९, १; ८. १९, ४.
सुऽभगस्य ३. १८, ५; ४. १, ६; ८. ४, १९.
सुऽभगा १. ४८, ७; ८९, ३; ९२, १२; २. ३२, ४; ३. १, १३; ६१, ४; ४. ५७, ६; ५. ५६, ९; ७. ७७, ३; ९५, ४; ८. २१, १७; १०. ७५, ८; ८५, २५.
सुऽभगाः ५. ४२, ८.
सुऽभगान् १. ४, ६.
सुऽभगां ३. ३३, ३; ६. ६४, ३; १०. ८५, ४५; ८६, ११; १४०, ५.
सुऽभगाय ७. ३०, ३.
सुऽभगासः २. २८, २.
सुऽभगासः ५. ६०, ६.
सुऽभगे १०. १४५, २.
सुऽभगे १. ३६, ६.
सुऽभगे १. ९२, ८; ११३, ७; २. ३२, ५; ४. ५७, ६; ७. ७६, ६; ९५, ६; ८. २४, २८; १०. १०, १०; १२; १०८, ५; ९.
सुभगे इति सुऽभगे १. १८५, ७; २. ३१, ५.
सुभगे इति सुऽभगे १०. ७०, ६.
सुऽभद्रं ८. १, ३४.
सुऽभद्रां १०. १०, १४.
सुऽभरः २. ३, ९.
सुऽभरे २. ३, ४; १०. ३५, १२.
सुऽभराः १. ११२, २; ९. ८६, ४१.
सुऽभरा १. ११२, २०.
सुभसत्ऽतरा १०. ८६, ६.
सुऽभागाः १. १६७, ७.
सुऽभागान् १०. ७८, ८.
सुऽभासे ८. २३, २०.
सुऽभु २. ३५, ७.

सुऽभृतः २. १, १२; ८. १९, २७.
सुऽभृतं ४. ५०, ७; ९. ९७, २४; १०. १७०, २.
सुऽभृतस्य १०. १४७, ४.
सुऽभोजसं ७. ९२, ३.
सुऽभ्वः १. ५२, १; ४; ४. १७, २; ५. ४१, १३; ५५, ३; ५९, ३; ८७, ३; ६. ५२, १.
सुऽभ्वं ७. ६७, ८; ९. ७९, ५.
सुऽभ्वे ६. ६६, ३.
सुऽमख २. १८, ४; ४. ३, १४.
सुऽमखं १०. ५०, १.
सुऽमखस्य १. १८१, ४.
सुऽमखाः ५. ८७, ७.
सुऽमखाय १. ६४, १; १६५, ११; ४. ३, ७; ५. ४१, १४.
सुऽमखासः १. ८५, ४.
सुऽमंगलः २. ४२, १–३; ९. ८०, ३.
सुऽमंगलं १०. १०२, ११.
सुऽमंगलीः १. ११३, १२; १०. ८५, ३३.
सुऽमत्त १. १४२, ७; १६२, ७; ५. २, ४; ८. ८७, ४; १०. ३२, ३.
सुमत्ऽअंशुः १. १००, १६.
सुऽमतयः २. ३२, ५; ७. १८, २०.
सुऽमतये १. १५८, २; ६. २९, १.
सुऽमतिः १. २४, ९; ८९, २; १०७, १; ११४, ९; १२१, १५; २. ३४, १५; ३. १, २३; ३०, ७; ४. ४३, ७; ५०, ११; ५. ६५, ४; ७. ५७, ४; ५९, ४; ७०, २; ५; ८. २२, ४; ८६, ४; १०३, ९; ९. ८८, ७; १०. ३१, ६; ४०, १२; १४३, ४.
सुमतिऽभिः २. १६, ८; ४. २३, २; ७. ५७, ५; ८. २२, २; ६; २६, ९.
सुऽमतिं १. ७३, ६; ७; ११४, ३; ४; ११७, २३; १५१, ७; १५६, ३; १६६, ६; १७१, १; २. ४३, ३; ३. १, १५; ४, १; ३३, ११; १२; ५७, ६; ४. ४, ६; ८; ५. १, १०; २७, ३; ३३, १; ४१, १८; ७०, १; ६. २, ११; १५, ९; ५१, १२; ५७, ५; ६२, ७; ७. ६, ६; १८, ४; २४, ६; ३१, १०; ३९, १; ६०, ११; १००, २; ८. २, २१; ३१, ७; ५१, ५; ९. ९६, २; ९७, २६; १०. ११, ७; १४८, ३.
सुऽमती ४. १, २; ९. ७४, १.
सुऽमतीः १०. २०, १०; ४७, ७.
सुऽमतीनां १. ३, ११; ४, ३; १७, ४; १०. ८९, १७.
सुऽमतौ १. ९८, १; ३. १, २१; ५९, ३; ६. १, १०; ७. १८, ३; २०, ८; ४१, ४; ८. ३, २; ४४, २४; ४८, १२; १०. १४, ६; १६०, ५.
सुमत्ऽगणः २. ३६, ३.
सुमत्ऽजानये १. १५६, २.
सुऽमत्या १. ३१, १८; ५. २५, ३; ४२, ४; १०. २९, ८.
सुमत्ऽरथः ३. ३, ९; ८. ५६, ५.
सुमत्ऽरथा ८. ४५, ३९.
सुऽमनसः ४. ४, ९; ६. ५२, ५; ७. ४, ४; ७८, ५; १०. ३७, ७.
सुऽमनस्यमानः १०. ५१, ५; ७.
सुऽमनस्यमाना ६. ७४, ४.
सुऽमनस्यमानाः ६. ७५, ८; ७. ३३, १४.
सुऽमनाः १. ३६, २; ६; ५३, ४; ९१, ४; २. ३२, ५; ३. ४, १[२]; ९, ३; १८, १; ३५, ६; ८; ५४, २२; ४. ३, १५; १०, ३; १३, १; २०, ४; ५. १, २; ७. १, ९; ८, ५; ८६, २; १०. ३२, ८; ५३, ११; ८५, ४४; १००, ४; १४१, १; ४; १४९, ४.
सुऽमंतु १०. १२, ६; ६४, १.
सुमंतुऽनामा ६. १८, ८.
सुमंतुऽभिः १. १२९, ७.
सुमन्मऽभिः ३. २, १२; ८. १०१, ९.
सुऽमन्मा ७. ६८, ९.
सुऽमयं ८. ७७, ११.
सुऽमहः ४. ११, २; ६. ५०, २; १०. ७, ७.
सुऽमहसः ८. १८, १८.
सुऽमंहान् ७. ८, २.
सुऽमातरः १०. ७८, ६.
सुऽमायाः १. १६७, २.
सुऽमायाः १. ८८, १.
सुऽमारुतं १०. ७७, १; २.
सुऽमिता ५. ४५, २.
सुऽमिती ३. ८, ३.
सुमिते इति सुऽमिते १०. २९, ६.
सुऽमित्रः १. ९१, १२; १०. ६९, ३; ५; १०५, ११.
सुऽमित्राः १०. ६९, १.
सुऽमित्रेभिः १०. ६९, ८.
सुऽमित्रेषु १०. ६९, ७.
सुऽमित्र्याः १०. ६५, ३.
सुऽमीळ्हे ६. ६३, ९.
सुऽमृळीकः १. ३५, १०; ९१, ११; ११८, १; १३९, ६; ४. १, २०; ६. ४७, १२; ९. ६९, १०.
सुऽमृळीकाः ६. ५२, ९.
सुऽमृळीकान् ८. ६७, १.
सुऽमृळीकां ८. ६७, १०.
सुऽमृळीकाय १. १२९, ३; १३६, ६; ४. ३, ३.
सुऽमेकः ४. ६, ३.
सुऽमेकं १०. ९२, १५.
सुमेके इति सुऽमेके १. ११३, ३; १४६, ३; ३. ६, १०; १५, ५; ५७, ४; ४. ४२, ३; ५६, ३; ६. ६६, ६; ७. ५६, १७; ८७, ३.
सुऽमेधः १०. १३२, ७.
सुऽमेधसः १०. ६२, १.
सुऽमेधसं १०. ६५, १०.
सुऽमेधाः १. १८५, १०; २. ३, १; ३. १५, ५; ३८, १; ५७, ५; ६. ६७, ८; ७. ९१, ३; ८. ४८, १; ९. ९२, ३; ९३, ३; ९७, २३; १०. ४५, ७.
सुऽमेधां ८. ५, ६; १०. ४७, ६; १२५, ५.
सुम्नं १. ४३, ४; १०७, १; ११४, ९; १०; १५३, २; २. ११, १६; १९, ८; २०, १; २३, ८; ३३, १; ६; ३. १४, ४; ४२, ६; ५७, २; ४. ३०, १९; ४१, १; ५३, २; ५. ३, १०; ५३, ९; ६७, २; ६. ४, ८; २२, ४; २६, ७; ५३, ९; ६०, ११; ७०, ४; ८. ५, २७; ७, १५;

१६, १२; १८, १; १९, ४; ४६, १८; ७५, १६; ९८, ११; **९.** ७८, ३; **१०.** ३६, ६; ४०, ७; ४५, ९; ५०, ३.
सु॒म्न॒ऽय॒ता **२.** ३२, २.
सु॒म्न॒ऽयन् **१.** ११४, ३; १३८, १.
सु॒म्न॒ऽयंतः **८.** ७, ११.
सु॒म्न॒ऽयंतो **६.** ४९, १.
सु॒म्न॒ऽयवः **५.** ८, ७; **६.** १, ७; **७.** ७१, ३.
सु॒म्न॒ऽया **१०.** १०१, ४.
सु॒म्न॒ऽयुः **१.** ७९, १०; **२.** ३०, ११; **३.** २७, १; **६.** २, ३.
सु॒म्न॒ऽवरीं **१.** ११३, १२.
सु॒म्नस्य॑ **८.** ४९, ९; **९.** ९८, ५; **१०.** ५०, ७.
सु॒म्ना **१.** ३८, ३; १६९, १; **८.** २०, १६; ९०, ६.
सु॒म्नानि॑ **१.** १३०, ९; **३.** ३, ३.
सु॒म्नाय॑ **१.** १३०, ६; १८६, १०; **३.** २, ५; ३२, १३; **५.** २४, ४; **६.** ६८, १; **८.** ८, १६; २७, १०; ६८, १.
सु॒म्ने **२.** २५, ५; **६.** ६३, ११; **७.** ६६, १३; **८.** १३, ३; **९.** ८४, ३; १०८, ४; **१०.** २२, १२.
सु॒म्नेऽआपिः **१०.** ९५, ६.
सु॒म्नेन॑ **५.** ७३, ६.
सु॒म्नेभिः॑ **५.** ७५, ६; **६.** ६८, ३; **७.** ५६, १७; **८.** ९, २१.
सु॒म्नेषु॑ **५.** ५३, १; **६.** ५२, १४; **८.** ३, २.
सु॒म्नैः **१.** ४१, ८; १०६, ४; **६.** १५, ७; ४८, १२; **१०.** ९३, २; १३२, १; १४३, ६.
सु॒ऽयजं॑ **५.** ८, ३.
सु॒ऽयु॒ज्ञः **२.** २१, ४; **३.** १७, १.
सु॒ऽयु॒ज्ञाः **३.** ५१, ७; **५.** ४५, ४.
सु॒ऽयंतः **७.** २२, १.
सु॒यंतु॑ऽभिः **५.** ४४, ४.
सु॒ऽयमः॑ **९.** ९६, १५.
सु॒ऽयमं॑ **५.** २८, ३; **१०.** ८५, २३.
सु॒ऽयमंस्य **२.** २४, १५; **७.** ३५, २.
सु॒ऽयमा॑ **९.** ८१, ४; **१०.** ४४, २.
सु॒ऽयमाः॑ **३.** ७, ३.
सु॒ऽयमा॑त् **२.** २७, १७; २८, ११; २९, ७.
सु॒ऽयमा॑सः **१.** १८०, १; **३.** ६१, २.
सु॒ऽयमे॑भिः **५.** ५५, १.
सु॒य॒व॒स॒ऽअत् **१.** १६४, ४०; **१०.** १०६, १०.
सु॒ऽयवसः॑ **१.** १९०, ६.
सु॒ऽयवसं॑ **१.** ४२, ८; **६.** २८, ७.
सु॒ऽयवसाः॑ **२.** २७, १३.
सु॒य॒व॒सिनी॒ इति॑ सु॒ऽय॒व॒सिनी॑ **७.** ९९, ३.
सु॒ऽयवसे॑ **७.** १८, ४.
सु॒य॒व॒स्यू॒ इति॑ सु॒ऽय॒व॒स्यू॒ **६.** २७, ७.
सु॒ऽया॒माः **३.** ७, ९.
सु॒या॒शु॒ऽत॒रा **१०.** ८६, ६.
सु॒ऽयुक् **३.** ५८, २.
सु॒ऽयुंक्तान् **८.** ६९, १३.
सु॒यु॒क्ऽभिः **३.** ५८, ३.
सु॒ऽयुजः॑ **१.** १२१, १२; **५.** ३१, १०; ४४, ४; ६२, ४; **६.** ४४, १९; **७.** ७८, ४.
सु॒ऽयुजं॑ **४.** २३, ५.
सु॒ऽयुजा॑ **१.** ११३, १४; ११७, १५; **४.** १४, ३; ३३, १०; **७.** ७०, २; **१०.** १०५, २.
सु॒ऽरणः॑ **३.** ३, ९; २९, १४.
सु॒ऽरणे॑ **३.** ५३, ६.
सु॒ऽरणाः॑ **१०.** ६९, १; १०४, ८.
सु॒ऽरणा॑नि **५.** ५६, ८.
सु॒ऽरत्नः॑ **७.** ४५, १; **१०.** ७०, ९.
सु॒ऽरत्नाः॑ **१०.** १८, ७.
सु॒ऽरत्ना॑न् **१०.** ७८, ८.
सु॒ऽरत्ना॑सः **७.** ६७, ६; ८४, ५.
सु॒ऽरथः॑ **४.** २, ४.
सु॒ऽरथं॑ **८.** ५, १०.
सु॒ऽरथ॑स्य **३.** १४, ७.
सु॒ऽरथा॑ **१.** २२, २; **७.** ३६, ४; **१०.** ७५, ८.
सु॒ऽरथाः॑ **४.** ४, ८; **५.** ५७, २.
सु॒ऽरथा॑न् **८.** ६८, १६.
सु॒ऽरथा॑सः **८.** ७४, १४.
सु॒ऽरथे॑भिः **२.** १८, ५.
सु॒रभि **४.** ३९, ६; **१०.** ७०, ४.
सु॒र॒भिः **१.** १६२, १२; **९.** ९७, १९; **१०.** ५३, ३.
सु॒र॒भिःऽत॑मं **१.** १८६, ७.
सु॒र॒भिं **६.** २९, ३; **१०.** १०७, ९; १४६, ६.
सु॒र॒भिंऽत॑रः **९.** १०७, २.
सु॒र॒भीणि॑ **७.** १, १८; **१०.** १५, १२.
सु॒र॒भौ **५.** १, ६.
सु॒ऽर॒श्मिं **१०.** ३६, ८.
सु॒रा॑ **७.** ८६, ६.
सु॒ऽरा॒तयः॑ **५.** ७९, ४; **९.** ८१, ४; **१०.** ६५, ४; ७८, ३.
सु॒ऽराधसः **१.** २३, ६; **३.** ५३, १३; **८.** ४६, २४; ६५, १२.
सु॒ऽराधसं **८.** १४, १२; ४९, १; ५०, १; ६८, ६.
सु॒ऽरा॒धसा **१०.** १४३, ४.
सु॒ऽराधाः॑ **१.** १००, १७; **३.** ३३, १२; **४.** २, ४; ५, ४; १७, ८.
सु॒ऽरामे॑ **१०.** १३१, ४; ५.
सु॒रा॑याः **१.** ११६, ७; **१०.** १०७, ९.
सु॒रा॑यां **८.** २, १२.
सु॒रा॑ऽवतः **१.** १९१, १०.
सु॒रा॒श्वः **८.** २१, १४.
सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे **१.** १८८, ६; **१०.** ११०, ६.
सु॒ऽरुचः॑ **१.** १९०, १; **३.** ७, ५; **४.** २, १७; **५.** ३३, १०; **६.** ३५, ४.
सु॒ऽरुचे॑ **१.** ११२, १; **२.** २, ४; **३.** २, ५.
सु॒ऽरुचा॑ **३.** १४, ६.
सु॒ऽरूपः॑ **८.** ४, ९.
सु॒रू॒प॒ऽकृ॒त्नुं **१.** ४, १.
सु॒ऽरेक्णाः॑ **६.** १६, २६.
सु॒ऽरेतः॑ **१.** १२१, ५.
सु॒ऽरेतसं॑ **१.** १६०, ३.
सु॒ऽरेतसा **१.** १५९, २; **३.** १, १६.
सु॒ऽरेताः॑ **१०.** ४५, ८.
सु॒ला॒भि॒के **१०.** ८६, ७.
सु॒व॒ **३.** ५४, ११; ५६, ६[२]; **५.** ८२, ४; ५[२]; **९.** ६६, १९; **१०.** ३५, ७; ३७, ४.
सु॒ऽव॒च॒स्यां **१०.** ११६, ९.
सु॒ऽव॒ज्र **७.** ३०, १.

सुऽवज्रः १. १००, १८.
सुऽवज्रं ४. १७, ४; ८; ६. १७, १३.
सुऽवज्रा ७. ९३, ४.
सुवतात् ४. ५४, ३.
सुवति ४. ५४, ४.
सुवति ६. ७१, ४.
सुवतु १०. ३६, १४; १७५, १.
सुवते १. १३५, ८; १६४, २२; १०. ९१, ६.
सुवते ३. ५५, ५.
सुवंतु ७. ५०, ३.
सुऽवरत्रं १०. १०१, ६.
सुऽवर्चाः १. ९५, १; १०. १४, ८; ८५, ४४.
सुऽवर्णाः १०. ६८, ३.
सुऽवसनस्य ६. ५१, ४.
सुऽवसनानि ९. ९७, ५०.
सुवसि ४. ५४, २.
सुवसि ४. ५४, ५.
सुऽवह्ना ६. २२, ७.
सुऽवाचः ३. ७, १०; ७. १०३, ५; ८. ९६, १.
सुऽवाचं ३. १, १९.
सुऽवाचसा १. १८८, ७.
सुऽवाचा १०. ११०, ७.
सुवाति ५. ८२, ३; ९; ७. ४०, १; ६६, ४.
सुवाति ५. ४२, ३.
सुवाति इति ५. १, ४.
सुवानः ७. ३८, २; ९. ६, ३; ९, १; १८, १; ३४, १; ५२, १; ६६, २८; ८६, ४७; ८७, ७; ९१, २; ९२, १; ९७, ४०; ९८, २; १०७, ३; ८; १०; १०९, १६; १०. ३५, २.
सुवानं १. १३०, २.
सुवानस्य २. ११, २०; १९, १.
सुवानाः ९. १३, ५; ६५, २४; १०१, १०.
सुवानासः ८. ३, ६; ६, ३८; ५१, १०; ९. १०, ४; १७, २; ७९, १.
सुवाने ८. ५२, २.
सुवानैः ८. ७, १४.

सुवामि १०. १३७, ४.
सुऽवासाः १. १२४, ७; ३. ८, ४; १०. ७५, ८; १०७, ९.
सुऽवास्त्वाः ८. १९, ३७.
सुऽविज्ञानं ७. १०४, १२.
सुवितः १०. ५६, ३.
सुवितं १. १४१, १२; ४. ५५, ४; ७. ९१, २; १०. १४८, १.
सुवितस्य ७. १, २४; १००, २; ९. ४१, २; १०. ३१, ३; १००, ४.
सुविता १. ३८, ३; १०. ८६, २१.
सुवितानि ८. ९३, २९.
सुविताय १. ९०, ४; १०४, २; ११८, १०; १६८, १; १७३, १३; १८०, १०; १८१, ३; १८९, ३; २. २, ६; ३. २, १३; ५४, ३; ४. १४, ३; ५. ११, १; ४१, १८; ५७, १; ५९, १; ४; ८०, ३; ६. ३२, ४; ४०, ३; ७१, ३; ७. २, ६; ३५, १; ६६, १५; ७५, २; ७९, ३; ८५, ४; ८. ७, ३३; २७, १०; ९. ८२, ५; १०. ३५, ३; ४०, १; ६६, ३; ७४, २.
सुऽविदत्रः २. ९, ६.
सुऽविदत्रं २. १, ८.
सुऽविदत्राणि २. २४, १०.
सुऽविदत्रान् १०. १४, १०; १५, ३.
सुऽविदत्राभिः ७. ९१, ६.
सुऽविदत्रियेभ्यः १०. १७, ३.
सुऽविदत्रेभिः १०. १५, ९.
सुऽविद्वांसं ८. २४, २३.
सुऽविप्रः १. १६२, ५.
सुऽविवृतं १. १०, ७.
सुऽवीरः १. ९१, १९; ११६, २५; १२५, १; २. २७, १३; ३. २९, ९; ४. १७, ४; ५. ५३, १५; ५८, ४; ६. ४५, ६; ४७, २६; ५०, ९; ७. १५, ८; ८. १९, ७; ८४, ९; ९. २३, ५; ८६, ३९.
सुऽवीरं १. ३१, १०; ३४, १२; ८५, १२; ९२, ८; २. ३, ४; ५; ३. ८, २; ४. ३४, १०; ५. ४४, ६; ५७, ७; ६. ५, ७; १६, २९; १७, १३; ६५, ६; ७. १, ५; १५, ७; ३७, ६; ८. ५, १०; ९. ६८, १०; ९७, २६; १०. ५२, ५; ७७, ७; ९१, १५.
सुऽवीरां ६. १३, ५; ७. ५६, ५.
सुऽवीराः १. ५३, ११; १२२, ८; २. १, १६; २, १३; ११, २१; १३, १३; १४, १२; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; २३, १९; २४, १६; २७, १७; २८, ११; २९, ७; ३३, १५; ३५, १५; ३९, ८; ४०, ६; ४२, ३; ४३, ३; ३. ५३, १; ५. ४२, ८; ६. ४, ८; ७. १, २४; १०. १८, ९; १२८, ३.
सुऽवीराभिः ८. १९, ३०.
सुऽवीरां १. ४०, ४; ४. ३४, २; ७. २४, ६.
सुऽवीरासः १. ११७, २५; २. ४, ९; १२, १५; ७. १, ४; ८. ४८, १४; ९. ६१, २३.
सुऽवीरेण १०. १२२, ३.
सुऽवीरैः ८. २६, ७.
सुऽवीर्यं १. ३६, १७; ४०, २; ४४, २; ४८, १२; ७४, ९; ९३, २; ३; ९४, २; ११६, १९; १२७, ११; १२९, ७^{2}; २. १, ५; २, १०; ३. १०, ३; ८; १३, ७; २६, ३; ४. ३६, ६; ५. ६, १०; १३, ५; २६, ५; २७, ६; ६. ८, ६; १६, १२; ७०, ५; ७. १६, १२; ८. ३, ९; ११; ६, २३; १२, ३३; १९, २२; २२, १८; २३, १२; ३१, १८; ४६, ५; ९८, १२; ९. ८, २; ११, ९; १३, ४; ५; २०, ७; ४०, ५; ४३, ६; ४५, ६; ६२, ३०; ६३, १; ६५, ५; २४; ६६, २१; २७; ६७, १९; ६९, ८; ८५, ८; ८६, १८; १०. १२२, १; ४; १५३, १.
सुऽवीर्यस्य ३. १६, १; ३; ४. ५१, १०; ५. १६, ४; ६. ४७, १२; ७. ४, ६; ५६, १५; ९७, ४; ८. २३, २७; ९५, ४; ९. ८९, ७; ९५, ५.

सुऽवीर्या १. ३६, ६; ८. ६४, ९.
सुऽवीर्याय १. १८४, ४.
सुऽवीर्ये १. १०, ६; ३. १६, ४; ८. ४, ६.
सुऽवीर्येभिः ६. १०, ५.
सुऽवीर्यैः ४. ८, ६.
सुऽवृक्तयः ८. ८, २२.
सुऽवृक्ति १. ६१, २; ४; १६; १८४, ५; १८६, ९; ५. ४१, १०.
सुऽवृक्तिः १. १५३, २; ६. ११, ५; ७. २४, २; ९७, ९.
सुवृक्तिऽभिः १. ५२, १; ६१, ३; ६२, १; १६८, १; ३. ३, ९; ५१, १; ६२, १२; ५. २५, ३; ६. १५, ४; ६१, २; ७. ८३, ९; ९६, १; ८. ८, ३; ४०, १०; ८९, ७; १०. ४१, १; ६३, ५; ६४, ४.
सुऽवृक्तिं १. ६४, १; २. ४, १; ३५, १५; ३. ६१, ५; ५. ४१, २; ६. १०, १; ६; १६, २६; ७. ८, ३; ३१, ११; ३६, २; ७०, ७; ७३, ३; ९४, ४; ८. ९६, १०; १०. ३०, १; ७४, ५; ८०, ७; १०४, ७.
सुऽवृजनासु १०. १५, २.
सुऽवृत् १. १८३, २; १०. ३९, १; १०७, ११.
सुऽवृतं १. १११, १; १८३, ३; ४. ३३, ८; १०. ८५, २०.
सुऽवृता १. ४७, ७; ११८, २; ३; ४. ४४, ५; १०. ७०, ३.
सुऽवृधः ५. ५९, ५; १०. ६३, ५.
सुऽवृधं ५. ३२, ४; ९. ६८, ६.
सुऽवृधा २. २३, ९.
सुवे १०. १२५, ७.
सुऽवेदुनां १०. ११२, ८.
सुऽवेदं ४. ७, ६; ८. ४, १६.
सुऽवेदा ६. ४८, १५; ७. ३२, २५.
सुऽवेनीः १०. ५६, ३.
सुऽव्रतः १. १८०, ६; ९. २०, ५; ५७, ३.
सुऽव्रतं ६. ४९, १.
सुऽव्रतासः १. १२५, ७.
सुऽशंसः १. ४४, ६; ६. ५२, ६; ७. १६, ६; ३५, ६.
सुऽशंसाः २. २३, १०.
सुऽशर्का १०. ३०, १५.
सुऽशक्तिः ७. ३२, २१.
सुऽशमि ५. ८७, ९.
सुऽशमी ७. १६, २; १०. २८, १२.
सुऽशरणः ७. ३४, २२.
सुऽशरणाय ५. ४२, १३.
सुऽशर्मणः ३. १५, १.
सुशर्मऽभिः ८. १८, ४.
सुऽशर्माणः ६. ५१, ११; १०. ७८, २.
सुऽशर्माणं ५. ८, २; १०. ६३, १०.
सुऽशर्माणा १. ९३, ७.
सुऽशस्तयः ५. ४६, ६.
सुऽशस्ति १. १८६, १; ६. ६७, ३.
सुऽशस्तिः १०. १०४, १०.
सुशस्तिऽभिः १. २०, ७; ३. २६, ६; ५. ५३, ११; ८. ५, २४; २३, ६; १०. १४०, ३.
सुऽशिप्र १. ९, ३; १०१, १०; ३. ३२, ३; ५०, २; ५. २२, ४; ३६, ५; ६. ४६, ५; ७. २४, ४; ८. २१, ८; ६९, १६; ९३, १२; ९९, २.
सुऽशिप्रः २. ३३, ५; ३. ३०, ३.
सुऽशिप्रः २. १२, ६; ८. ६६, ४; १०. ९६, ३.
सुऽशिप्रं ८. ३२, ४; ६६, २.
सुऽशिप्राः ७. ३७, १.
सुशिल्पे इति सुऽशिल्पे ९. ५, ६; १०. ७०, ६.
सुऽशिश्वि १. ६५, २.
सुऽशिष्टौ १. १७३, १०.
सुऽशुक्वानः ५. ८७, ३.
सुऽशेवः १. २७, २; ९१, १५; १८७, ३; २. १, ९; ३. ५९, ४; ५; ५. १५, १; ४१, ५; ७. ४, ८; ७, ३; ५५, १; ८. ४८, ४; ७९, ७; १०. ४५, १२; ८५, २४.
सुऽशेवं ३. २९, ५; ५. ४२, २; ६. ५०, १; ७. ९७, ३.
सुऽशेवाः ४. ४, १२; ५. ३०, ६.
सुऽशेवा १०. १८, १०.
सुऽशेवौ ६. ७४, ४.
सुऽशेव्यं ५. ४३, १४.
सुऽशोकः १. ७०, १.
सुश्रवःऽतमः १. ९१, १७; १३१, ७; ३. ४५, ५; ८. १३, २; ४५, ८.
सुश्रवःऽतमान् ८. २०, २०.
सुऽश्रवसं १. ४९, २; ५३, १०; ९१, २१.
सुऽश्रवसा १. ५३, ९.
सुऽश्रवस्या १. १७८, ४.
सुऽश्रांतं १०. १७९, ३.
सुऽश्रियः ५. ७९, ४; ८. ८, १७; ९. ७, १.
सुऽश्रियै ३. ३, ५; ९. ४३, ४.
सुऽश्रुणं १०. ७४, १.
सुऽश्रुतः ३. ३६, १.
सुऽश्रुतः १०. ७४, १.
सुऽश्रुता २. ३९, ६.
सुऽश्रोतुः १. १२२, ६.
सुषिरांऽइव ८. ६९, १२.
सुष्ठु ८. २२, १८.
सुष्टुऽवाहः १०. १०७, ११.
सुऽसंरब्धाः १०. ७२, ६.
सुऽसंशिताः ५. १९, ५.
सुऽसंसत् ७. ९, ३.
सुऽसंसदं १. ११२, ७; ९. ६८, ८.
सुऽसंस्कृता ८. ७७, ११.
सुऽसंस्कृताः १. ३८, १२.
सुऽसखा १०. ९१, १.
सुऽसखा ८. ४८, ९.
सुऽसखायः १. १७३, ९; १०. ३१, १.
सुऽसंकाशा १. १२३, ११.
सुऽसदं ८. ५८, ३.
सुऽसंदृशः ५. ५७, ४.
सुऽसननानि ७. १२, ३.
सुऽसना १. ४२, ६.
सुऽसंनितः ८. ४६, २०.
सुऽसनितः ३. १८, ५.
सुऽसनिता १०. ३६, ९.
सुऽसंदृक् ७. ३, ६.
सुसंदृक्ऽभिः ७. ७९, १.
सुऽसंदृशः १. १४३, ३; १०. ७८, १.
सुऽसंदृशं १. ८२, ३; ७. १०, ३.
सुऽसंदृशा ७. ९, ४.
सुऽसमिद्धः १. १३, १.

सुऽसंमिद्धाय ५. ५, १.
सुऽसमिधा ५. ८, ७; ७. १७, १.
सुऽसंमुब्धं १. १५८, ५.
सुऽसंपिष्टं ४. ३०, ११.
सुऽसंमृष्टासः ३. ४३, ६.
सुऽसरणं ८. २७, १८.
सुऽसत्वा १०. ७५, ६.
सुऽसत्यः ८. ३३, ५.
सुऽसंह १०. १९१, ४.
सुऽसहा १. १८६, २; ९. २९, ३; ९४, ५.
सुऽसहाः १०. ३८, ३.
सुऽसहान् ६. ४६, ६.
सुऽसाः ८. ७८, ४.
सुऽसामनि ८. २५, २२.
सुऽसामनि ८. ६०, १८.
सुऽसाम्ने ८. २३, २८; २४, २८; २६, २.
सुऽसारथिः ६. ७५, ६.
सुसावं ४. ४५, ५; ७. २२, १; ८. ८, ४; ९. १०७, १.
सुऽसुतः ९. ८५, १.
सुऽसुतं ३. ३६, ७; १०. ३०, १३.
सुऽसुतस्य ३. ५०, २; ५३, २; ४. २०, ४; ३५, २; ५. २९, ३; ३३, ७; ७. २९, १.
सुऽसुता ७. ६७, ४.
सुऽसुताः ५. ३०, १०.
सुऽसुतिं १०. ३९, ७.
सुसुपानं ४. १९, ३.
सुसुपुः ७. १८, १४.
सुसुप्वांसः १. १६१, १३.
सुसुप्वांसं १. ११७, ५.
सुसुम १. १३७, ९; ८. १७, १.
सुसुम १. १०१, ९; ४. १६, १.
सुसुऽस्मान् १०. ३, १.
सुऽसुम्नं ६. ४९, १०.
सुऽसुम्नस्य १०. १०४, ५.
सुऽसुम्ना ५. ७५, २.
सुऽसुम्ना १०. १३२, २.
सुसुम्ने इति सुऽसुम्ने ६. ५०, ३.
सुसुऽवांसं ८. ३२, २१.
सुसुऽवुपः १०. ९४, १४.

सुऽसूः ५. ७, ८.
सुऽसूतं २. १०, ३.
सुसूदः १. ७३, ८.
सुसूदः ७. १, २०; २५.
सुसूदत १०. ७०, २.
सुसूदति १. १०५, १४; १४२, ११; ५. ५, २.
सुसूदथ ५. ५४, ७.
सुसूदिम १. १८७, ११.
सुऽसूमा २. ३२, ७.
सुऽसेकं १०. १०१, ५.
सुऽसेचनं १०. १०१, ६.
सुऽसोमया १०. ७५, ५.
सुऽसोमायां ८. ६४, ११.
सुऽसोमे ८. ७, २९.
सुऽस्तुत १. १२९, ११.
सुऽस्तुतः १. १५७, ३; १७७, ५; २. २४, ९; ४. २४, २; ५. २७, २; ८. ६, १२; ७४, ८; ९. १०८, १२.
सुऽस्तुतं ५. १३, ५.
सुऽस्तुतयः ३. १९, ३; ७. ९९, ७; १०. ९१, १२.
सुऽस्तुता ६. ६३, ६; ८. १३, २३; १००, ११.
सुऽस्तुताः १. १६६, ७; ९. ५, ५.
सुऽस्तुतिः १. १७, ९; ३. ६२, ७; ४. २४, १; ५. ४२, १४; ६. ६३, ८; ७. ५८, ६; ९१, २.
सुस्तुतिऽभिः ६. २४, ६; ७. ९०, ७.
सुऽस्तुतिं १. ७, ७; ११७, १२; ११८, ७; २. १६, १; ३३, ८; ३७, ६; ४. ४३, १; ५८, १०; ५. ४३, १०; ६६, ३; ६. १६, ६; ५२, १६; ६१, ७; ७. २२, ५; ५८, ३; ८. १, १६; ५, ३०; ६, ३२; ८, ६; १२, ३१; ३४, १; ३८, ६; ४३, २; ५२, ८; ७५, ६; ८७, ४; ९६, १२; १०३, १४; ९. ६२, ३; ६५, ३; ६६, २२; ८५, ७; १०. ९१, १३; १८८, २.
सुऽस्तुती २. ३२, ४; ३. ३८, ८; ५. ४३, २; ७. १४, २; ९. ७१, ८.
सुऽस्तुतीः ८. १७, ४; ३५, २०.

सुऽस्तुतीनां १०. २६, २; ३.
सुऽस्तुत्या ८. १६, ३; ९६, २०.
सुऽस्तुभः ५. ७५, ४; १०. ७८, ४.
सुऽस्तुभा १. ६२, ४.
सुऽस्तोः १०. १०४, ५.
सुस्थाने इति सुऽस्थाने ९. ९७, २७.
सऽस्थामा १०. ४४, २.
सुऽस्नुपे १०. ८६, १३.
सुस्रोत् १०. १०१, ८.
सुस्वति २. १६, ५.
सुस्वयंत ७. ३६, ६.
सुस्वयंती इति १०. ११०, ६.
सुस्वये ४. २४, २; २५, ७; ६. २३, ३; ९. २१, २.
सुऽस्वरुः ५. ४४, ५.
सुस्वानः ९. ६, ८; ६५, १८; ६७, ३.
सुस्वानं ९. १३, २.
सुस्वानासः ९. १०१, ११; १०. १४८, १.
सुस्वानेभिः ४. २९, २.
सुस्विऽतराय ७. १९, १.
सुस्वि १. ६१, १५; ६. २३, २; ९.
सुस्वेः ४. २५, ६.
सुऽहना ७. २५, ५.
सुऽहनानि ४. २२, ९.
सुऽहनाय १०. १०५, ७.
सुऽहंतु ७. १९, ४; ३०, २.
सुऽहवः २. ३३, ५; ३. ४९, ३; ४. १, ५; ५. ४२, १६; ६. २१, ८; २९, ६; ५२, ६; ७. १, २१.
सुऽहवं १. ५८, ६; ४. १६, १६; ६. ४७, ११; ४९, ९; ८. २२, २; १०. ३६, ७; ८; ३९, १; ६३, ९.
सुऽहवस्य ३. १५, १.
सुऽहवा १. १२३, १३; ७. ४०, ४; ४४, २; ८२, ४; ९३, १; १०. १४१, ४.
सुऽहवा ६. ५२, १६; ८. २२, १; १०. ३९, ११; ९२, १३.
सुऽहवाः २. ३६, ३; ५. ४६, ७.
सुऽहवानि ७. ३५, ३.
सुऽहवा २. ३२, ४.
सुऽहवासः ३. ६, ८; ४. १९, १.

सुऽहविषे ४. २, ४.
सुहवींतुऽनाम्ने ९. ८५, ६.
सुऽहवेभिः १०. ६४, ४.
सुऽहव्यं १. ७४, ५.
सुऽहव्यां ३. ४३, १.
सुऽहस्तः १. १६४, २६.
सुऽहस्ता ३. ५७, २; ५. ४३, २; ४.
सुऽहस्ताः ४. ३३, ८; ५. ४२, १२; ७. ३५, १२; ९. ९७, ३७; १०. ६६, १०.
सुऽहस्ताः ४. ३५, ३;९;१०. ३०, २.
सुऽहस्त्य ९. १०७, २१.
सुऽहस्त्यः १. ६४, १.
सुऽहस्त्यः ९. ४६, ४.
सुऽहस्त्यं १०. ४१, ३.
सुऽहार्दं ८. २, ५.
सुऽहिरण्यः १. १२५, २; ४. ४, १०.
सुहुतऽअदः ९. ७१, ४.
सुऽहुतं ८. ६०, १४.
सुऽहोता ७. ६७, ३.
सुऽहोता ८. १०३, १२.
सूः १. ३२, ९; १४६, ५.
सूकरः ७. ५५, ४.
सूकरस्य ७. ५५, ४.
सूक्तऽवाकं १०. ८८, ८.
सूक्तऽवाकेन १०. ८८, ७.
सूक्तऽवाचः ५. ४९, ५.
सूचीकाः १. १९१, ७.
सूच्या २. ३२, ४.
सूत १०. ३१, १०.
सूत १०. ६१, २०.
सूतवे १०. १८४, ३.
सूते ७. १०१, ३.
सूते १. १६४, १७.
सूदऽदोहसः ८. ६९, ३.
सूदनं ४. ३९, ५.
सूदं ९. ९७, ४४.
सूदय ४. ४, १४; ७. १६, ९.
सूदयत १. ७१, ८.
सूदयंतु ४. ३९, १; ४०, १.
सूदयंते ८. २३, ८.
सूदयाति २. ३, १०; ३. ४, १०.
सूदयामि १. १६२, १७.
सूदयित्न्वः १०. ६४, ९.
सूदाः ७. ३६, ३.
सूदैः १०. ६१, २.
सूनया १. १६१, १०.
सूनरः ८. २९, १; १०. ११५, ७.
सूनरं १. ४०, ४; ५. ३४, ७.
सूनरि १. ४८, १०.
सूनरी १. ४८, ५; ८; ४. ५२, १; ७. ८१, १.
सूनवः १. ३७, १०; ४५, ५; ८५, १; १५९, ३; ६. ५०, ४; ५२, ९; ७. ८१, ४; ८. २०, १७; १०. ५६, ६; ६२, ५; १७६, १.
सूनवः २. ३६, २.
सूनवि ८. ६८, १५.
सूनवे १. १, ९; २६, ३; ३४, ६; ५९, ४; १२७, ५; १४३, १; २. २८, ५; ३. १, १२; ८. ४८, ४; १०. २५, ३.
सूनाः १. १६२, १३.
सूनां १०. ८६, १८.
सूनुः १. २७, २; ६२, ९; ६६, १; १०३, ४; १८९, ८; ३. १, २३; २५, १; २८, ३; ३३, ५; ६. २, ७; १२, १; ७. ६७, १; ९. ९, ३; १०७, १३; १०. ४५, ५; ६१, २४; ६३, १७; ९५, १२.
सूनुऽभिः १. १००, ५.
सूनुं १. ६४, १२; १२७, १; १६६, २; १८५, २; ३. ११, ४; ४. २४, १; ५. ४२, २; ६. ५, १; ६, १; ४९, २; ६२, ६; ६६, ११; ८. २३, २५; ६९, ४; ७१, ११; १०. २०, ७; ३९, १४.
सूनुऽमतः ३. २४, ५.
सूनूइति ८. २५, ५.
सूनून् ५. ४२, १५.
सूनृत ८. ४६, २०.
सूनृता १. ८, ८; ३०, ५; ४०, ३; ५१, २; १३४, १; १३५, ७; ६. ४८, २०; ७. ३७, ३; ५७, ६; ८. १३, ८; १४, ३; ४५, १२; १०. १४१, २.
सूनृताः १. ४८, २; ११३, १२; १२३, ६; ३. ३१, २१; ६१, २; ७. ७९, ५; १०. ३९, २; १११, १०.
सूनृतानां १. ३, ११; ९२, ७; ११३, ४; १८; ३. ३१, १८; ७. ७६, ७; ८. ३२, १५.
सूनृताभिः १. १२५, ३; ७. ६७, ९; ८. १९, २२; १०. ६१, २१; १०४, ५.
सूनृताये १. १२१, १४; १०. ६१, २५.
सूनृताऽवतः १. ८२, १.
सूनृताऽवता ८. ९७, ६.
सूनृताऽवति १. ९२, १४.
सूनृताऽवती १. २२, ३; ७. ८१, ६.
सूनृताऽवते ७. ७४, २.
सूनृताऽवरि ४. ५२, ४.
सूनृताऽवान् १. ५९, ७.
सूनृते ४. ५५, ९.
सूनृते १. १२३, ५; १२४, १०; ८. ९, १७.
सूनो इति ८. ४०, ९.
सूनो इति १. ५८, ८; ३. १, ८; २४, ३; २५, ५; २८, ५; ४. २, २; ११, ६; ३७, ४; ५. ३, ९; ४, ८; ६. १, १०; ४, १; ४; ५, ५; ११, ६; १३, ४–६; १५, ३; १८, ११; २०, १; २१, ११; ५०, ९; ७. १, २१; २२; ३, ८; ७, ७; १६, ४; ८. १९, ७; २५; ६०, २; ७५, ३; १०. ११, ७; ५०, ६; १४२, १.
सूनोः १. ११७, ११; ९. १९, ४.
सूभर्वे १०. १०२, ५.
सूभर्वाः १०. ९४, ३.
सूयत १०. १३२, ४.
सूयते ४. ५८, ९; १०. ११६, ३.
सूयते ८. ६४, १०.
सूरः १. ५०, ९; ६६, १; ७१, ९; १२१, ६; ७; १०; १३; १२२, १५; १३०, ९; १४१, १३; १४९, ३; १७४, ५; ४. ५, १३; १६, १२; १४; ४१, ६; ४५, ६; ५. ३१, ११; ७९, ९; ६. २, ६; ३, ३; ४८, १७; ४९, ३; ५१, २; ५६, ३; ७. ३, ६; ४५, २; ६९, ४; ८. १, ११; ६, २५; ७, ३६;

५६, ५; ९२, ३१; ९. १०, ९; ६३, ८; ९; ६६, १८; २२; ८६, ३४; ९१, ३; १११, १; १०. ८, ३; २७, २०; २९, ५; ९२, ७; ८; १२१, ६; १३२, ६; १७९, २.

सूर॑ऽचक्षसः १. १६, १; ८९, ७; ११०, ४; ७. ६६, १०.

सूरं॑ १. ८६, ५; ९. ६५, १; ६७, ९.

सू॒रयः॑ १. २२, २०; ४८, ४; ७३, ५; ९; ९७, ३; ४; १२५, ७; १४१, ३; ८; २. १, १६; २, ११–१३; ४. २९, ५; ५. ६, २; १०, ३; ६; १६, ५; १७, ५; ५२, १६; ६६, ६; ७९, ७; ६. २५, ७; ७. १६, ७; ६६, १३; ७४, ५; ९०, ६; ८. १०, ४; ६०, ६; ९४, ७; ९. ९८, १२; ९९, ३; १०. ६५, ४; ६६, २; ११; ७८, ६.

सू॒र॒यः ४. ३४, ६; ३७, ७.

सू॒रये॑ १. ३१, ७; ५. २७, ४.

सूराः॑ ९. १०, ५.

सूरा॑त् १. १६३, २.

सूरा॑य १. ५०, २.

सू॒रिः १. १२२, ८; १५३, २; १७६, ४; १८०, ६; १८१, ४; १८६, ३; २. ६, ४; ६. २३, १०; २९, ५; ३७, ५; ७. १, २३; ८. ५, ३९; ४६, २४; ७०, १३; १५; ९. ६७, २; १०. ६१, १८; ८१, ६; १६७, ४.

सू॒रिऽभिः॑ १. ५१, १५; १८६, ६; ५. ४१, १५; ४२, ४; ५२, १५; ६. २६, ७; ६३, ११; ७. ३२, १५; ६६, ९; ९२, ४; ८. १८, ४; २६, १२; १०. २३, ३; ११५, ७.

सू॒रिऽभ्यः॑ १. १८०, ९; २. ४, ९; ६. ४, ८; ६८, ७; ७. १, २४; १८, २१; ३०, ४; ८१, ६; ८. १३, १२.

सू॒रिं १. ६१, ३; ११९, ३; १७३, ७; ६. ४५, ३३.

सू॒रिषु॑ ५. ७९, ६; ८६, ६; ६. ४७, १९; ७. १९, ७; ८४, ३; ८. २६, १; ९. ९८, ८; १०. १४७, ३.

सू॒रीन् १. ५४, ११; १७३, ८; २. ३५, ६; ६. ८, ७; १७, १४; ३७, ४; ४४, १८; ७. ३, ८; ३८, ३; ५७, ७; ६७, १०; १०. ११५, ५; ९.

सूरे॑ १. ३४, ५; ३. १५, २; ६. ३१, १; ७. ६३, ५; ६६, ४; १२; ८. १, २९; १३, १३; २७, २१; ७२, १७; ९. ९७, ३८.

सू॒रे ४. ३, ८.

सू॒रः॑ १. १२२, ११; १२; ३. ३१, १४; ५. ३३, ८; १०. १३, १.

सू॒र्तं १०. ८२, ४.

सू॒र्म्ये॑ ८. ६९, १२.

सू॒र्म्याँ ७. १, ३.

सू॒र्य॒ १. ५०, ४; ७; ८; ११; ४. ३१, १५; ५. ४०, ५; ६. ५०, २; ७. ६०, १; ६२, २; ८. ९३, १; ४; १०१, ११; १२; १०. ३७, ३–५; ७–१०.

सूर्यः॑ १. २३, १७; ३५, ७; ४३, ५; ४६, १०; ५६, ४; ८३, ५; ८४, १; ९०, ८; १०१, ३; १०५, १२; ११५, १; २; ५; १२४, १; १४६, ४; १५७, १; १६०, १; १९१, ८; ९; २. ११, २०; २३, २; २४, ९; ३. १४, ४; ३०, १२; ५४, १९; ४. १, १७; १३, १; १४, २; २६, १; ५८, ४; ५. ४४, ७; ४५, २; ९; १०; ५४, ५; ५९, ३; ६३, ४; ६. ४, ३; ६; १२, १; ३०, २; ४८, २१; ६१, ९; ७. ८, ४; ३५, ८; ३६, १; ४७, ४; ६०, २; ४; ६१, १; ६२, १; ६३, १; ७९, १; ८१, २; ८. ३, २०; १२, ७; १८, ९; २५, १९; ३२, २३; ४३, ३२; ४८, ७; ५६, ५; ५८, २; ७०, २; ९. ५, ११; ४१, ५; ५४, ३; ६३, १३; ६४, ९; ३०; ८४, २; ८६, २९; १०. ३५, ८; ३७, २; ६०, ११; ७७, ३; ८८, ६; ८९, २; ९०, १३; १३८, २–४; १५८, १; १५९, १; १७०, ३.

सूर्यः॑ऽइव ४. ३८, १०; ८. ६, १०; १०२, १५; ९. ५४, २; १०. ६९, २; १७८, ३.

सूर्य॑ऽत्वचः ७. ५९, ११.

सूर्य॑ऽत्वचं ८. ९१, ७.

सूर्य॑ऽत्वचा १. ४७, ९; ८. ८, २.

सूर्यं॑ १. ७, ३; २३, २१; ३२, ४; ३५, ९; ५०, १; १०; ५१, ४; ५२, ८; १००, ६; १८; ११२, १३; ११७, ५; १३०, २[२]; १५१, ५; १६४, २५; १७५, ४; २. १२, ७; १९, ३; ५; ३. ३१, १५; ३२, ८; ३४, ९; ३९, ५; ४४, २; ४. १३, २; ३; २५, ४; ३०, ४; ६; ५. २७, ६; ४०, ६; ९; ६३, ७; ८५, २; ६. १७, ३; ५; ३०, ५; ५२, ५; ७२, १; २; ७. ४४, ३; ६०, ३; ६६, १५; ७८, ३; ८०, २; ८२, ३; ९९, ४; १०४, २४; ८. ३, ६; ६, २०; ७, २२; १२, ३०; २५, २१; २९, १०; ५२, १०; ८९, ७; ९८, २; ९९, ३; ९. ४, ६; १७, ५; २३, २; २८, ५; ३७, ४; ४२, १; ६३, ७; ८६, २२; ९१, ६; ९७, ३१; १०७, ७; २०; ११०, ३; १०. १६, ३; ३१, ८; ३५, २; ४३, ५; ५८, ८; ५९, ४; ६; ६०, ५; ६२, ३; ६५, ११; ६७, ५; ७२, ७; ८८, ११; १४१, ३; १५४, ५; १५६, ४; १७१, ४.

सूर्यं॑ऽइव ५. २७, ६.

सूर्य॑ऽरश्मिः १०. १३९, १.

सू॒र्य॒ऽश्वि॑तः १०. ९४, ५.

सूर्य॑स्य १. १४, ९; ४७, ७; ४८, ७; ९२, १२; १०८, १२; १०९, ७; ११३, ९; ११५, ३; ४; ६; ११६, १७; ११७, १३; ११८, ५; १२२, २; १२३, १२; १२४, ८; १३७, २; १६४, १४; २. ११, ६; १९, ४; ३३, १; ३. ५, ५; २२, ३; ३१, १७; ४९, ४; ५३, १५; ४. ११, १; १३, ४; १७, १४; २८, २; ४०, १; ४३, २; ५. ४, ४; २९, ५; १०; ३७, १; ४०, ८; ५९, ५; ६२, १; ८; ६९, ३; ७६, ३; ७९, ८; ८१, ४; ६. २०, ५;

३१, ३; ५८, ३; ६३, ५; ७. २, १; ६, ७; ३०, २; ४१, ४; ६३, २; ७५, ५; ७६, ३; ८१, २; ९८, ६; ८. १२, ९; ७२, १६; १०१, २; ९. १, ६; ६१, ८; ७१, ९; ७२, ३; ७५, १; ७६, ४; ८६, ३२; ९३, १; ९६, ५; ९७, ३३; ११३, ३; १०. ३, २; ७, ३; १०, ९; २७, २१; ३५, ५; ३७, ६; ४९, ७; ५९, ५; ६६, २; ११२, ३; १२३, १; १३९, ४; १५१, ५.

सूर्यस्यऽइव १. १००, २; १३५, ९; ५. ५५, ३; ४; ७. ३३, ८; ९. ६४, ७; ६९, ६; १०. ४८, ३; ९१, ४.

सूर्या ५. ७३, ५; १०. ८५, ७; १२.

सूर्याऽइव १. १६७, ५.

सूर्याः ८. ७०, ५.

सूर्याःऽइव १. ६४, २; ८. ३, १६; ३४, १७.

सूर्याचंद्रमसा १. १०२, २.

सूर्याचंद्रमसौ १०. १९०, ३.

सूर्याचंद्रमसौऽइव ५. ५१, १५.

सूर्यात् ५. ४२, ९; ६. ५९, ८; १०. १८१, ३.

सूर्याम् ४. ४४, १; १०. ८५, ९; १५; ३४; ३८.

सूर्यामासा ८. ९४, २; १०. ६४, ३; ६८, १०; ९२, १२; ९३, ५.

सूर्याय १. २४, ८; ११३, १६; १२३, ३; ५. ३३, ४; ८५, १; ७. ८७, १; ८. ७, ८; १०. १४, १२; ३७, १; ९६, ११; १११, ३.

सूर्यायाः १. १८४, ३; ४. ४३, ६; ६. ६३, ६; १०. ८५, ६; ८; १३; १४; ३५.

सूर्यायै ६. ५८, ४; ८. २२, १; १०. ८५, १७.

सूर्यावसू इति ७. ६८, ३.

सूर्यासः १. १२५, ६; ९. १०१, १२; १०. ८८, १८.

सूर्ये १. २३, १७; ५९, ३; ६१, १५; १०४, ६; १३५, ३; १९१, १०; ४. ३१, ५; ६; ५. १, ४; ३७, ५; ५४, १०; ६. ११, ५; ४४, २३; ४६, ४; ८. २७, १९; ६८, ९; ९. ४, ५; १०, ८; ९४, १; ९७, ४१; १०. १२, ७; ९३, १२.

सूर्ये १०. ८५, १६; २०.

सूर्येण १. ३३, ८; ६२, ५; ९८, १; २. ११, ४; २०, ५; ५. ८५, ५; ६. २१, ३; ३२, २; ७. ४४, ४; ६३, ४; ९१, १; ८. ९, १८; ३५, १; ९. २, ६; २७, ५; १०. ६२, ११; ८५, १; १०७, २; १११, ५; ७.

सूर्यत्वाःऽइव ५. ७८, ५.

सृकं १०. १८०, २.

सृके १. ३२, १२.

सृकाणां १. १६४, २८.

सृज १. ३६, ९; ८०, ४; ७. ८६, ५; ९. १००, ३.

सृज १. १३, ११; २३, २३; २४; २८, ९; ३१, १८; १८८, १०; ३. ४, १०; १६, ६; ४. ४, २; ३; ६. २०, ८; ३६, ४; ७. ८६, ५; ८. ३२, २३; ९. ६, ६; १६, ३; ५१, १; १०. १६, ५; ८५, २२; ९८, १२; १२०, ३.

सृजः २. ११, २; ४. १७, १; ५. ३२, १; १०. १११, ९.

सृजः १. १८९, ५.

सृजत् १. ७१, ५; १७४, ४; ४. २७, ३; ९. ६४, १०.

सृजत् १. ५५, ६; ७. १०४, २०; १०. ११३, ४; १२४, ७.

सृजत ९. ६२, २१; १०४, २.

सृजत १. ९, २; ३९, २०.

सृजतः ८. ७२, ७.

सृजतं १. १५१, ६.

सृजतं ५. ६२, ३; ८. ३५, २०.

सृजति १. ४८, ६.

सृजति १०. ४२, ९.

सृजते ५. ३४, ८; ७. ८१, २.

सृजथः १. १८०, ६; १०. ६५, १२.

सृजध्वै ६. ४८, ११.

सृजन् ८. ४३, ३२; ७६, ३.

सृजंत १०. ६२, ७.

सृजंति ८. ७, ८.

सृजंति ५. ३०, १३; ५३, ६.

सृजंतु ५. २, ५; ६; १०. १९, ७.

सृजस्व १. १०१, १०; १०. ८५, २७.

सृजात् १०. १०८, ५.

सृजानः ७. ३८, २; ९. ६४, १४; ७६, १; ८६, २२; ९५, २; ९७, १८; १०. २२, ४; ८९, १२.

सृजानं ९. ८, ५.

सृजाना ६. ६, ५.

सृजानाः ६. ३२, ५.

सृजामि १. १९, ९.

सृजामि ८. ४५, २२.

सृज्यते ९. ८४, ३.

सृज्यते ९. ७१, १.

सृज्यमानः ९. ८८, ५; ९५, १.

सृंजयाय ६. २७, ७.

सृंजये ४. १५, ४.

सृण्यः ४. २०, ५.

सृण्यः १०. १०१, ३.

सृण्या १. ५८, ४.

सृण्याऽइव १०. १०६, ६.

सृत्वरीणां १०. ७५, १.

सृत्वा ९. ९६, २०.

सृप्रऽकरस्नं ८. ३२, १०.

सृप्रऽदानुं १. ९६, ३.

सृप्रदानू इति सृप्रऽदानू ८. २५, ५.

सृप्रऽभोजसं ६. ४८, १४.

सृप्रं ४. ५०, २.

सृप्रऽवंधुरः १. १८१, ३.

सृप्रा ३. १८, ५.

सृबिंदं ८. ३२, २.

सृष्टः ७. ८७, १; ९. ८७, ७.

सृष्टा १. ६६, ४; १४३, ५; ७. ३, ४.

सृष्टाः १. ७२, १०; ७. १८, १५; ९. २२, १; १०. ९८, ६.

सेकं ३. ३१, १; ४. १६, ३.

सेकं १. १८१, ८; ८. ८७, १.

सेक्ताऽइव ३. ३२, १५.

सेचते १०. ९६, १.

सेतवः ९. ७३, ४.

सेतुः ८. ६७, ८.

सेतुं ९. ४१, २.
सेतू इति ७. ६५, ३.
सेतृऽभिः ७. ८४, २.
सेतौ १०. ६७, ४.
सेदु ७. ५९, ७.
सेदुतुः ८. २५, ८; १०. ११४, ३.
सेदथुः ७. ७०, १.
सेदुथुः ४. ५६, ७.
सेदिम १. ८९, २; ५. ८, ४; ८. ४९, ६.
सेदिरे १. २५, १३; ४. ७, ५; ५. ८, २; ६. १५, ८; ८. १०२, १८; १०. २१, ७.
सेदुः ३. ३१, ९; ४. १, १३; ६, ११; ५०, ३; ६. ३०, ३; ७. ३३, ९; १०. ७३, ११; १३०, २.
सेदुषः ५. १५, २.
सेध ६. ४४, ९; ८. ६०, २०; १०. २५, ७.
सेध ६. ४७, २९; ८. ७९, ९^{२}; १०. ९८, १२; १६६, ३.
सेधत १०. ७६, ४.
सेधत ८. १८, १०; १०. १७५, २.
सेधतं १. ३४, ११; १५७, ४; ८. ३५, १६.
सेधति ९. ७१, ८.
सेधति १. ७९, १२; ७. १५, १०; ८. २३, १३.
सेधतु १०. ३६, ४.
सेधन् ९. ११०, १२.
सेधंति १. १०५, ११.
सेधंतु १०. १००, ८.
सेधीः १०. २७, २०.
सेनया ८. ७५, ७; १०. १५६, २.
सेना ९. ९६, १; १०. १४२, ४.
सेनाऽइव १. ६६, ४; १४३, ५; ७. ३, ४.
सेनाः १. १८६, ९; २. ३३, ११; ५. ३०, ९; ७. २५, १; १०. १०३, १; ४; ७.
सेनाऽजुवा १. ११६, १.
सेनाऽनीः ७. २०, ५; ९. ९६, १; १०. ३४, १२; ८४, २.
सेनाभिः १०. २३, १.
सेना १. ३३, ६.
सेन्यः १. ८१, २; ७. ३०, २.
सेपुः ६. २९, १.
सेवते १०. ११७, २.
सेहानः ८. ३६, १; ३७, २.
सेहानायाः १०. १५९, २.
सैर्याः १. १९१, ३.
सो इति १. १९१, ११; १०. ११, ३; २३, ४; ६३, १६.
सोतं ८. १, १७.
सोत ८. १, १९; ९. १०८, ७.
सोतः ८. २, २३.
सोतन ८. ४, १३.
सोतरि १०. ७६, २; १००, ९.
सोतवे १. २८, १.
सोता ४. ३, ३; ७. ९२, २; ८. ३३, १२.
सोतारः ९. १६, १; १०९, ११.
सोतारः ८. २, २५; ९. ६२, १८.
सोतु १०. ७६, ६.
सोतुः ७. २२, १.
सोतु ८. १९, १८.
सोतृऽभिः ८. ४९, ५.
सोतृऽभिः १. २८, ८; ४. २९, २; ९. ३०, २; ८६, १२; ९६, १६; १०७, ८; २६.
सोतोः १०. ८६, १.
सोत्वासः १०. १६०, २.
सोभरयः ८. १९, ३२.
सोभरि ८. ५, २६.
सोभरी ८. २२, १५.
सोभरीणां ८. २०, ८.
सोभरीऽयवः ८. २०, २.
सोभरे ८. १९, २; २०, १९; २२, २.
सोभर्याः ८. १०३, १४.
सोम १. ९१, ९; १०; ११; १३; १५; १७; ८. ४८, ७; ८; ९. ४, ७; २४, ३; ३१, ३; ४०, ६; ४३, ६; ५५, १; ६१, २४; ६२, २५; ६३, ३०; ६७, २८; ६८, ७; ७९, ३; ८६, २३; १००, २.
सोम १. ४३, ७; ९^{२}; ९१, १–२; ३^{२}; ४–८; १२; १४; १६; १८; १९; २१–२३; ९३, ५; १६४, १९; १८७, ९; ४. २८, १; ५; ६. ५१, १४; ५२, ३; ७. १०४, २५; ८. ४८, ४; ६; ९; १३; १५; ७८, ८; ७९, ३; ७; ८; ९. १, १; २, १; ४, १–३; ६, १; ८, ३; ८; ९, ७; ११, ७–९; १४, ८; १६, ८; १७, ५; १९, १; २; ७; २०, ३; ५; ७; २२, ७; २३, ६; २४, ४; २९, ३; ४; ३०, ३; ३२, ४; ३३, ६; ३६, २; ६; ४०, ३; ४; ४१, ६; ४२, ६; ४३, ४; ४६, ५; ५१, ४; ५५, ३; ५६, ३; ५९, १; ३; ६०, ४; ६१, ५; ६; १५; २३; ६२, २७; ६३, १; ११; १६; १८; २३; २४; २८; २९; ६४, १; ८; २५; २६; ३०; ६५, १३; १८; १९; २१; ६६, २; ३; ५–७; १५; १६; १८; ६७, १; ५; ६; १३; १६; १९; २६; ३०^{२}; ६८, १०; ६९, ७; ८; ७०, ९; ७४, ९; ७५, ५; ७६, ३; ७८, २; ५; ८०, २; ४; ५; ८१, ३; ८२, २; ४; ८५, १; ४; ५; ८६, ५; १८; २२; २४; ३०; ३७–३९; ४७; ४८; ८७, ९; ८८, ३; ४^{२}; ८९, ७; ९०, ५; ९१, ६; ९२, ४; ९४, ५; ९६, ३; ४; ११; १३; १६; २४; ९७, १४; १५; १८; २५; २७; ३३; ३६; ४२; ४८; ५०; ५८; १००, ३; ५; ६; १०६, ४; ७; १०७, ४; ६; १०; १२; १९; २०; २२–२४; १०८, १; १५; १०९, १; २; ४; ५; ७; १०; १८; ११०, २; ७; १२; ११३, २; ४^{२}; ११४, १; ३; ४; १०. २५, २–७; ५७, ६; ५९, ४; ८५, ४; १०७, २; १२४, ६; १२८, ५; १३९, ४.
सोमऽअर्दः १०. ९४, ९.
सोमऽआहुतः १. ९४, १४.
सोमः १. १८, ४; ५; २३, २०; ४५, १०; ४७, १; ६५, ५; ८०, २; ८४, १; ८६, ४; ९१, २०^{३}; १०८,

२; ६; १३५, २[२]; १३६, ४; १३७, ३; १६४, ३५; १७७, ३; ४; १९१, ६; **२.** १२, १४; १८, ६; ४०, ६; ४१, ४; **३.** ३५, ६; ७; ३६, ६; ४४, १; ५०, १; ५८, ९; ६२, १३–१५; **४.** २४, ५; ४९, २; ५८, ९; **५.** ३६, २; ४०, २; ४३, ५; ४४, १४; ४६, ४; ५१, ४; **६.** २९, ४; ३४, ४; ३८, ४; ४१, ३–५; ४३, १; ४४, १; २४; ४७, ४; ७५, १२; १८; **७.** २४, २; २६, १; २; २९, १; ३५, ७; ४९, ४; ६४, ५; ९८, ५; १०४, १२; १३; **८.** ३, २०; ९, ४; १७, ६; ७; ११; २२, ८; ३२, १६; ४८, १०; ११; ६४, १०; ६६, १५; ७९, १; ८२, ५; ७; ८; ९२, २४; ९४, ४; ९६, २१; १००, २; १०४, ९; **९.** २, ५; १२, ३–५; ८; १३, १; १६, ४; १७, ३; १८, १; २०, ६; २३, ५; २४, ७; २५, ५; २७, ३; २८, २; ६; ३०, ४; ३४, २; ३६, ५; ३७, १; ५; ४२, ५; ४३, ३; ४४, २; ३; ५; ४७, १; ३; ५४, ३; ५६, १; २; ६१, २५; ६२, १६; ३०; ६३, ३; १३; ६५, २०; ६६, २९; ६७, ११; ६८, ९; ६९, १; ४; ७०, ७; ७१, ९; ७२, १; ४; ५; ७; ७४, ७; ७८, ४; ८१, २; ८२, १; ८४, २–४; ८६, ३; ७; ९; १३; १६; १९; २१; ८७, ४; ७; ८८, ५; ८९, १; ९२, ३; ६; ९६, १; ५–७; ९; १५; १७; १८; २३; ९७, १०; २१; ३५; ३७; ३९–४१; ४५; ४६; ५६; ९९, ६; १०१, ६; ७; १६; १०३, ४; १०६, २; १०; १०७, १; ७–९; ११; १७; १८; १०८, १३; १०९, १९; ११०, १०; **१०.** १६, ६; ३०, ५; ३२, ९; ३५, २; ४८, १०; ५९, ७; ६५, १; २; ८५, १; २; ९; ४०; ४१; ८९, ५; ६; ९१, १५; १००, ४; १०३, ८; १०४, १; १०८, ११; १०९, २; ११२, ५; ११६, ३; १२४, ४; १३०, ४; १५४, १; १६९, ३; १७३, ३; १७४, ३.

सोमः॑ऽइव **६.** ८, १.

सोम॑कः **४.** १५, ९.

सोम॑ऽकामं **१.** १०४, ९; **८.** ६१, २.

सोम॑ऽगोपाः **१०.** ४५, ५; १२.

सोम॑ऽजामयः **१०.** ९२, १०.

सोमऽधानः **६.** ६९, ६.

सोमऽधानं **९.** ७०, ९; ९७, ३३; १०८, १६.

सोमऽधाना **६.** ६९, २.

सोमऽधानाः **३.** ३६, ८.

सोम॑ऽपीतिं **१.** ७६, ३.

सोमऽपते **३.** ३२, १; **५.** ४०, १; **८.** २१, ३.

सोमऽपरिबाधः **१.** ४३, ८.

सोमपर्व॑ऽभिः **१.** ९, १.

सोमऽपा **१.** २१, ३; **४.** ४९, ३.

सोम॑ऽपाः **१.** ३०, ११.

सोमऽपाः **१.** ५४, ८; **२.** १२, १३; **३.** ४९, १; **८.** २, ४; १४, १५; **१०.** १०३, ३; १५२, २.

सोमऽपाः **१.** ४, २; १०, ३; २९, १; ३०, १२; **३.** ३९, ७; **४.** ३२, १४; **६.** ४५, १०; **८.** ३२, ७; ३३, १५; ४६, २६; ६६, ६; ९२, १८; ९७, ६; ९८, ५.

सोमऽपातमः **१.** ८, ७; **८.** ६, ४०; १२, १.

सोमऽपातमं **६.** ४२, २; **८.** १२, २०.

सोमऽपातमा **१.** २१, १.

सोमऽपां **३.** ५१, ५; **८.** १७, ३; ९२, ८.

सोमऽपावन् **१.** ५५, ७.

सोमऽपावा **५.** ४०, ४.

सोमऽपाव्नः **८.** ७८, ७.

सोमऽपाव्ना **१.** ३०, ११.

सोमऽपाव्ने **७.** ३१, १; ३२, ८.

सोम॑ऽपीतये **१.** २, ३; ८, १०; १४, १; ६; १६, १; ८; २१, ३; २२, ९; १२; २३, ४; ७; १०; ४४, ९; ४८, १२; ९२, १८; १११, ४; १३७, ३; **२.** ४१, १; २१; **३.** ४१, १; ४२, ३; **४.** ४६, ३; ७; ४७, १; ३; ४९, ३; **५.** ५१, ३; ७२, १; ३; **६.** ६०, ९; **७.** ६६, १७; **८.** १, २४; ३, १७; ८, ५; १३, २७; २१, ४; २२, ८; ३८, ७; ४२, ४; ६१, १; ७६, ४; ९३, २०; ९४, ३; ९; १०३, १४; **१०.** ८६, २; १०१, १२.

सोमऽपीथं **१०.** १५, ८.

सोमऽपीथाय **१.** ५१, ७.

सोम॑ऽपृष्ठाय **८.** ४३, ११; **१०.** ९१, १४.

सोम॑ऽपृष्ठासः **८.** ६३, २.

सोमऽपेयं **१.** १२०, ११; **२.** १८, ४; ५; **३.** ४३, १; **५.** २९, ५; **६.** ४०, ४.

सोमऽपेयाय **१.** ४५, ९; **३.** २५, ४; ५२, ८; **७.** २४, ३; **८.** ६, ४५; १४, १२; **१०.** ११२, २.

सोमं **१.** १५, १; ५; १६, ७; २१, १; २८, ६; ९; ३२, ३; १२; ४४, १४; ४७, ३; ५; १०; ८४, ११; ८९, ३; ९१, १; १०१, ९; १०३, ६; १०९, ४; १३०, २; १३७, ३; १७९, ५; **२.** ११, ११; १५; १७; १४, १; ६–९; १६, २; ४; ५; २१, १; २२, १; ३०, ७; ३६, १; २; ३७, १–३; ५; **३.** २२, १; २९, १६; ३०, १; ३२, १; २; ५; ९; १०; ३५, ९; ३६, ७; ८; ३७, ८; ४०, २; ५; ४२, १; ८; ४६, ५; ४७, १–४; ४८, ३; ४; ५०, ३; ५१, ७–९; ५२, ७; ५३, ४; ६; ५८, ७; ६०, ५; ६२, १८; **४.** १८, ३; २२, १; २३, १; २४, ६; ७; २६, ६; ७; ३४, ७; ३७, ३; ४१, ८; ४५, ५; ४९, ६; ५०, १०; **५.** २९, ७; ११; ३४, ३; ३७, ४; ४०, १; ५१, १२; ६०, ८; ६४, ७; ८५, २; **६.** १७, १; २३, ३; ४; ७; ४४, १४; २०; ४७, ६; ५७, २; ६८, १०; ६९, ३; **७.** २२, १; ३२, ८; ४१, १; ५१, २; ६६, १८; ८५, १; ९०,

२; ९१, ४; ९२, २; ९८, ३; ८. १, १७; १९; २, ११; २३; २५; ४, ४; १०; ११; १३; ९, ७; १२, १६; १७, १; २१, ३; ३१, २; ३२, २४; ३५, १; ७; १६; ३६, १; ३८, ४; ४८, ३; ५१, १; ५२, १–३; ५७, २; ४; ६९, ३; १०; ७६, ७; ९; १०; ८७, ४; ९१, १; ९५, ३; १००, ८; १०१, १०; ९. १, ६; ९; ४, ४; ११, ५; १६, ३; ३०, ६; ३४, ३; ३५, ५; ५१, १; २; ६२, २१; ६३, २१; ६८, ८; ७२, २; ७८, ३; ८४, ५; ८५, २; ८६, १७; ३६; ८८, १; ९५, ३; ९७, ४; ३४; ३५^{२}; १०१, ३; १०७, १; १०९, ११; १२; ११३, १; ११४, २; १०. १४, १३; २४, १; २८, १; ३०, ३; १३; १५; ३६, ८; ३९, २; ४८, ५; ४९, १०; ६५, १०; ७६, ७; ८; ८५, ३^{२}; ९४, १३; ९६, १३; ११२, ६; ११६, १; ८; १२५, २; १४१, ३; १४८, २; १६०, २–४; १७३, ६.

सो॒म॒ऽमार्दः ७. २१, २.

सोम॑ऽइव १. ११६, २४.

सोम॑रभःऽतरेभ्यः १०. ७६, ५.

सोम॑ऽराज्ञीः १०. ९७, १८.

सो॒म॒ऽव॒र्ती १०. ९७, ७.

सोम॑ऽवल्या १०. ११३, ८.

सोम॑ऽशितं ७. १०४, १९.

सोम॑ऽशिताः १०. १०८, ८.

सो॒म॒ऽवृ॒द्ध ३. ३९, ७.

सोम॑ऽवृद्धः ६. १९, ५.

सो॒म॒ऽसुत् ७. ६८, ४.

सो॒म॒ऽसुतः॑ १. ८९, ४.

सो॒म॒ऽसुता॑ ७. ९३, ५.

सोम॑ऽसुतिं ७. ९३, ६.

सो॒म॒सुत्ऽभिः ४. २४, ८; ८. ४६, २६.

सो॒म॒ऽसुत्वा॑ १. ११३, १८.

सोम॑स्य १. ४, २; १६, ३; २२, १; २३, २; ३४, २; ४६, ५; १२; १३; ४७, ९; ५५, २; ८५, १०; ८७, ५; १०८, १; ३; ५–१२; १०९, २; ११७, १; ११९, ९; १३४, १; १३६, ६; १३९, २; २. ८, ६; १४, ४; १५, २–९; १६, ६; १७, १; ३. १, १; १२, ३; ४०, ७; ४२, ४; ५३, २; ४. २०, ४; २६, ७; ३२, १७; ३५, २; ५. २९, ३; ४३, ४; ६. २८, ५; ६८, ११; ६९, ५; ७; ८. १, २०; ४, १२; १२, १२; १४, ७; १७, १५; ३२, १; २८; ३४, १०; ३७, १; ४८, १४; ५३, ४; ६५, ३; ६८, १४; ७२, १७; ७७, ४; ८५, १; ९२, ५; २३; ९७, ११; ९. १२, २; ८०, १; ८१, १; ८७, ८; १०. ५५, ८; ८५, ५; १०४, ६; ११३, १; ११४, ५; ११६, २; ११९, १; १६७, ३.

सोम॑स्यऽइव १०. ३४, १; १४९, ५.

सोमा॑ः १. २, १; १३५, ६; १३७, १; ३. ३६, २; ४०, ४; ४. १४, ४; १७, ६; ५. ३०, ११; ८. २, ७; १०; २८^{२}; ५२, १०; ९३, २५; ९. ८, १; १२, १; १३, ३; १६, ५; १७, १; २१, १; २३, १; ३३, ३; ४२, ३; ४६, २; ६२, २२; ६३, ४; २५; ६४, ६; २८; ६९, ९; ८७, ५; ८८, ६; ९७, २०; २६; ९८, ११; १०१, ४; १०; १०. ४२, ८; ४६, ७; ७८, २; ९६, ६.

सोमा॑ःऽइव ५. २७, ५.

सोमा॑त् ७. ३३, २.

सोमा॑न् ३. ३६, ३; ७. ९८, २; १०. २८, ३; ४२, ५.

सो॒मानं॑ १. १८, १.

सोमा॑नां १. १३४, ६; ४. २२, १४; ४७, २; ८. ९३, ३३.

सोमा॑पूषणा २. ४०, १; ३.

सोमा॑पूषणौ २. ४०, ५.

सो॒मा॒पू॒ष॒ऽभ्यां॑ २. ४०, २.

सोमा॑य ८. ४८, १२; ९. ११, ४; ६५, ७; १०३, १.

सोमा॑रुद्रा ६. ७४, १–३.

सोमा॑रुद्रौ ६. ७४, ४.

सोमा॑सः १. ५, ५; ७; १६, ६; २३, १; ५३, ६; १३५, ६; १३७, १; २; १६८, ३; ३. ३२, १५; ३६, ३; ४; ४६, ४; ४. ४२, ६; ५. ३०, १०; ५१, ७; ७. ३२, ४; ८. ९, १४; ७६, ८; ९३, ६; ९. १०, १; ३; १७, २; २२, १; ३; २३, ४; २४, १; ३१, १; ३२, १; ३३, १; ४६, ३; ६३, १५; ६४, ४; १०१, ८; १२; १०७, १४; १०. ४३, ४; ७; ४८, ४.

सो॒मिन॑ः १. २२, ४; ४९, १; १५१, २; ७. १०३, ८; ८. १७, ३; २४, २९; ४५, १६; ६२, १; ६; १०. ४४, ५; ५७, १; ९४, १; १७१, १; २.

सो॒मि॒नः ७. ३२, ९.

सो॒मिनि॑ ७. ३२, १२.

सो॒मी ४. २५, ५; ८. ३४, २.

सोमे॑ १. ५, २; ८०, १; १७७, २; ३. ३५, ९; ४०, १; ६. २३, १; ५; ६; १०; ४०, ३; ७. ९४, १०; १०३, ७; ८. ५०, ५; ९. ९७, ३५; ११३, ३; ६; १०. २८, १२; ४२, १; ४३, २.

सोमे॑न १. १६३, ३; ५. ३४, २; ५१, ९; ९. ११३, ७; १०. ५७, ३; ८५, २^{२}; ९७, २२; १०९, ५.

सोमे॑भिः २. १४, १०; ११; ६. २०, १३; ४२, २; ३; ८. १, २३; १२, २०; ४६, २६.

सोमे॑षु ६. २४, १; ८. १३, १; ६६, ६; ९२, २६; ९७, ६.

सोमे॑ऽसोमे ८. ९३, १७.

सोमै॑ः १. १०८, ४; २. १४, ३; ३. ३५, ५; ४. ४१, ३; ६. २६, ६; ७. २४, १; ३७, १; ८. २, ३७; ६२, ५; १०. ४३, ६; १४८, ३.

सो॒म्यः ८. ९३, ८; ९५, ८; ९. ६७, ८.

सो॒म्यं १. १४, १०; १९, ९; २. ३६, ४; ६; ३७, २; ३. ५१, ११; ५३, १०; ६. ६०, १५; ७. ७४, २; ८. ५, ११; ८, १; ४; १०, ४;

२४, १३; ३३, १३; ६५, ८; ९. ७४, ३; १०. ९४, ९; १७०, १.
सोम्यस्य॑ १. १०५, ३; ३. ४८, १; ४. ३५, ४; ४४, ४; ६. २०, ३; ३७, २; ८. १९, २; १०. ३२, १; ५०, ७; ९४, ८.
सोम्या ५. २९, ८.
सोम्याः १०. ५३, ७.
सोम्यात् १. १८२, ८.
सोम्याना॑ं १. ३१, १६; ४. १७, १७; ८. १७, १४; १०. १६, ८.
सोम्याय॑ ३. ३३, ५; ४. २५, २.
सोम्या॑सः ६. ७५, १०.
सोम्यास॑ः ३. ३०, १; १०. १४, ६; १५, १; ५; ८.
सोम्यासः १०. ३०, १४.
सोम्ये ७. ५९, ६.
सोम्येन॑ ४. २६, ५.
सोम्येभ्य॑ः ८. ३२, ५.
सोसवीति ३. ५६, ७.
सौक्रु॑त्याय १०. १३६, ४.
सौध॑न्वनाः १. १६१, २; ७; ८; ३. ६०, १; ४; ४. ३५, १; ८.
सौधन्वनाः १. ११०, ४.
सौध॑न्वनासः १. ११०, २; ८; ३. ६०, ३.
सौधन्वनेभि॑ः ३. ६०, ५.
सौभगऽत्वं १. ३४, ५.
सौभगऽत्वस्य॑ १. ९४, १६.
सौभगऽत्वाय॑ १०. ८५, ३६.
सौभ॑गं १. ३६, १७; ४८, ९; ४. ५४, ६; ५. ५३, १३; ८२, ४; ८. ११, १०; १०. ३६, १३.
सौभ॑गस्य ३. १६, १; ४. ५५, ८; ७. २१, ८.
सौभ॑गा १. ३८, ३; ३. १५, ४; ७. ३, १०; ८. १, ३२; ७८, ८; ९. ४, २; ५५, १; ६२, १; ६७, ५.
सौभ॑गानि १. ९२, १५; ५. ४२, १८; ६. ५, २; १३, १.
सौभ॑गाय १. १६४, २७; ३. ८, २; ११; ५. २८, ३; ६०, ५; ७. ७५, २; ८. ५९, ५; ९. ९५, ५; ९७, ५; १०. ११६, २.
सौभ॑गेभिः १. ११२, २५.
सौभा॑ग्यं १०. ८५, ३३.
सौमनसं ८. ५९, ७; ९. ९७, २८.
सौमनसाय॑ १. ७६, २; ९२, ६; १०८, ४; ५. ४२, ११; ६. ४४, १६; ७. ९३, ६.
सौमनसे ३. १, २१.
सौम्या॑ः ८. ५९, ४.
सौव॑श्व्यं ६. ३३, १.
सौव॑श्व्ये १. ६१, १५.
सौश्रवसं ७. ९८, ४.
सौश्रवसा ६. १३, ५.
सौश्रवसानि॑ ६. १, १२; ७४, २.
सौश्रवसाय॑ १. १६२, ३; ६. ६८, ८; १०. ३६, ७.
सौश्रवसेषु १०. ४५, १०.
स्कंद॑ति १०. १७, १२.
स्कंदति ५. ५२, ३.
स्कंधा॑सिऽइव १. ३२, ५.
स्कन्नः १०. १७, १३.
स्कन्नं ७. ३३, ११; १०. १८१, ३.
स्कभायत् ५. २९, ४; ६. ४४, २४.
स्कभायत॑ १०. ७६, ४.
स्कभायति १०. ४४, ८.
स्कभितः १०. १४९, २.
स्कभिताऽस॑ः १. ३४, २.
स्कभित्वी १०. ६५, ७.
स्कभी॑यान् १०. १११, ५.
स्कभ्नाति॑ १०. ६, ३.
स्कंभः ४. १३, ५; ९. ७४, २; ८६, ४६; १०. ५, ६.
स्कंभथुः ६. ७२, २.
स्कंभऽदे॑ष्णाः १. १६६, ७.
स्कंभ॑नेन ३. ३१, १२; ६. ४७, ५; ७२, २; १०. १११, ५.
स्कंभ॑नेभिः १. १६०, ४.
स्कंभं १०. ४४, ४.
स्कंभास॑ः १. ३४, २.
स्कंभुः १०. ६५, ४.
स्कंभेन॑ ८. ४१, १०.
स्त इति॑ स्तः १. ६१, ८.
स्तः ८. ३, २.
स्तन् १०. ९२, ८.
स्तन॑ः १. १६४, ४९.
स्तनथा॑ः ५. ८३, ३.
स्तनऽभुजः १. १२०, ८.
स्तनं॑ १. १६९, ४; ७. ९६, ६.
स्तनय॑ ५. ८३, ७.
स्तनय॑त्ऽअमाः ५. ५४, ३.
स्तनय॑त्ऽभिः ४. १७, १२.
स्तनय॑न् १. ५८, २; १४०, ५; ५. ८३, २; ९; ६. ४४, १२; ९. १९, ३; ८६, ९; १०. १६८, १.
स्तनय॑न्ऽइव १०. ४५, ४; ६७, ५.
स्तनय॑ंतं १. ६४, ६; ५. ४२, १४; ९. ७२, ६; १०. ४०, ८.
स्तनय॑ंति १. ७९, २.
स्तनयंति ४. १०, ४; १०. ७५, ३.
स्तनय॑ंती ९. ८७, ८.
स्तनयित्नुना॑ ५. ८३, ६.
स्तनिहि ६. ४७, ३०.
स्तनौ॑ऽइव २. ३९, ६.
स्तभायुः ६. १७, ७.
स्तभायत् ४. ५, १; ६, २.
स्तभायन् ४. २१, ५; १०. ३, २.
स्तभितं १०. १२१, ५.
स्तभुऽयन् १०. ४६, ६.
स्तभुऽयमा॑नः ८. ६, १६.
स्तभुऽयमा॑नं ३. ७, ४.
स्तभ्नामि १०. १८, १३.
स्तं १०. ८५, ४२.
स्तंभी॑त् १. १२१, २.
स्तर॑ते १. १२९, ४.
स्तरामहे ८. ७५, ७.
स्तरीः १. १२२, २; ७. १०१, ३; ८. ५१, ७; १०. ३१, १०.
स्तरी॑मणि १०. ३५, ९.
स्तयैः ४. १९, ७; ७. २३, ४.
स्तयैं १. ११६, २२; ११७, २०; ७. ६८, ८.
स्तवं॑ २. ११, ६[३].
स्तव १०. ८९, १.
स्तव॑ः ९. ५५, २.
स्तव॑त् ६. ५९, ४.
स्तवत् ६. ४७, १५; ८. ८६, २.
स्तव॑ते २. २४, १; ८. २४, १६.

स्तवते १. १५४, २; १७८, ४.
स्तवथ ४. २१, २.
स्तवथैः ७. १, ८.
स्तवध्यै ७. ३७, १; ८.
स्तवंत ७. ३०, ४.
स्तवंत ४. २२, ७.
स्तवंते ६. २६, ७.
स्तवंते ६. २०, १०; १०. ६५, ४.
स्तवमान १. १४७, ५.
स्तवमानः १. १३९, ६; ७. १९, ११; ८. २४, ४.
स्तवमानेभिः १. ६२, ७.
स्तवसे ५. १०, ७.
स्तवसे १. १६९, ८; १०. १४८, ५.
स्तवान् २. १९, ५; २०, ५; ६. २४, ८.
स्तवान ३. ४०, ३.
स्तवानः १. १२, ११; ३१, ८; ५१, ९; ११३, १७; १३०, १०; २. ३३, ११, ४. ११, २; ५. १०, ७; ६. ८, ७; ५०, ६; ७. ३६, ५; ८. २३, ५; ९. ९७, ५.
स्तवानः ६. ४६, २.
स्तवाना ४. ५५, ४.
स्तवानाः ७. ६२, ३.
स्तवानेभिः १. १६९, ८.
स्तवाम १. १६, ९; ८. २४, १९.
स्तवाम २. ११, ६; ४. २१, ४; ३९, १; ८. ६२, १२; ९५, ६; ९६, ६; १००, ३.
स्तवामहे ८. ४६, १७.
स्तविष्यसे ८. ७०, १४.
स्तविष्यामि १. ४४, ५.
स्तवे ५. ७३, ४; १०. २२, २.
स्तवे १. ९२, ७; ६. १२, ४; ७. १२, २; १०. ११५, ७.
स्तवेत ५. १८, १.
स्तवै ३. ३२, १४; ९. ५३, २; १०. ३३, ५.
स्तामुः ७. २०, ९.
स्तिऽपा ७. ६६, ३.
स्तिऽपाः १०. ६९, ४.
स्तियानां ६. ४४, २१; ७. ५, २.
स्तीन् ७. १९, ११; १०. १४८, ४.
स्तीर्णऽबर्हिः ५. ३७, २.
स्तीर्णऽबर्हिषे १०. २१, १.
स्तीर्णं १. १३५, १; १७७, ४; २. ३, ४; ३. ३५, ७; ५. १८, ४; ८. ९३, २५.
स्तीर्णाः ३. १, ७.
स्तीर्णे ४. ६, ४.
स्तुकाऽइव ९. ९७, १७.
स्तुकाऽविनां ८. ७४, १३.
स्तुतः १. १६९, ४; ६. ६३, ८; ८. २, २९; ४३, १७.
स्तुतः १. ८२, ३; १७१, ३; १७७, १; १९०, ८; २. ३३, १२; ३. ५, ९; १८, ४; ४. १६, २१; १७, १९; २१, १; २९, १; ३२, ८; ५. १०, ७; ३३, १; ६. २४, २; ७. ८, ५; ३८, ३; ८. १४, ४; ९. ६२, १५; १०. ५०, २; ६१, १६; ९३, ४; १००, १.
स्तुतं ८. ३५, ११.
स्तुतयः ६. ३४, १.
स्तुतस्य ७. ५६, १५.
स्तुताः ४. ३७, ७; ५. ५२, १४; ६. ५०, १४.
स्तुतासः १. १७१, ३; ६. ५०, १५; ७. ५७, ६; ७; ८. ३०, २.
स्तुतिं १०. ३१, ५.
स्तुतीः १. ८४, २.
स्तुप् ९. ९६, १८.
स्तुभः १. १९०, ७; ३. ५१, ३; ९. ६८, ८; ८६, १७.
स्तुभा १. ६२, ४.
स्तुभ्वा १. ६६, २.
स्तुमसि ६. २३, ५; १०. १४८, १.
स्तुवतः १. ३३, ७; ५. ५३, १६; ७. १८, १८; ३३, ५; ८. ३, १४; १३, २६; १९, १२; २४, १४; ८५, ४; ६.
स्तुवतां ६. ५४, ६.
स्तुवते १. ६२, १; ११६, ७; २३; ११७, ७; २. २२, ३; ४. १७, १८; २१, ७; ९; ५. ४२, ७; ६. २३, ३; ६२, ५; ७. ८८, ६; ९५, ६; ९७, १०; ८. १, २२; ७, ३५; ५०, १; ८८, ३; १०. ४६, १०.
स्तुवन् ४. ५१, ७.
स्तुवंतः ४. २०, १०; ६. २९, ४; ८. ३, १४.
स्तुवंते १. १४७, ५; २. २०, ३.
स्तुवंति ८. ३, ८; १५, ६.
स्तुवाना ७. ९६, ३.
स्तुवीत ४. ५५, ६.
स्तुवीमहि ८. २२, ६.
स्तुषे १. ४६, १; १२२, ७; २. ३१, ५; ५. ५८, १; ६. ४९, १; ५१, ३; ६२, १; ८. ४, १७; ५, ४; ७, ३२; २४, १; ६३, ३; ६५, ५, ७४, १; ८४, १.
स्तुषे १. १२२, ८; १५९, १; २. २०, ४; ५. ३३, ६; ६. ४८, १४; ८. २१, ९; २३, २; ७; १०. ९३, ९.
स्तुषेय्यं १०. १२०, ६.
स्तुहि २. ३३, ११; ५. ५३, १६; ८३, १; ८. १, ३०[2]; १३, १०; २४, २२; ९६, १२; १०३, १०.
स्तुहि १. १२, ७; २२, ६; ५४, २; १३६, ६; १७३, ५; २. ८, १; ३. २३, ३; ५१, ३; ५. ४२, ७; ११; १५; ५३, ३; ८. २०, १४; २४, २३; २६, १०; ९९, ४; १०२, १०.
स्तूपः १. २४, ७.
स्तूपैः ७. २, १.
स्तूयमानाः १. १०७, २.
स्तूयसे ३. २२, १.
स्तृणन् ९. ५, ४.
स्तृणंति ८. ४५, १.
स्तृणानासः १. १४२, ५; २. ११, १६.
स्तृणीत १. १३, ५; ५. २६, ८; ७. ४३, २.
स्तृणीतं ८. ७३, ३.
स्तृणीतां ७. १७, १.
स्तृणीते ६. ६७, २.
स्तृणीमहि ३. ४, ४.
स्तृणोषि १. १२९, ४[2].

स्तृऽभिः १. ६८, ५; ८७, १; १६६, ११; २. २, ५; ३४, २; ४. ७, ३; ६. ४९, ३; १२.

स्तेगः १०. ३१, ९.

स्तेनः २. २८, १०; ४२, ३; ७. १०४, १०.

स्तेनःऽइव १०. ९७, १०.

स्तेनं ५. ७९, ९; ६. ५१, १३; ७. ५५, ३; ८. ६७, १४; १०. १२७, ६.

स्तेनाः ५. ३, ११.

स्तेनेभ्यः २. २३, १६.

स्तेयऽकृत् ७. १०४, १०.

स्तोकं १०. ९५, १६.

स्तोकाः ३. २१, २; ३; ५.

स्तोकानां ३. २१, १.

स्तोकासः ३. २१, ४.

स्तोत ८. १, १; १६, १.

स्तोतवे ८. ४, १७; ७२, ५.

स्तोता १. ३८, ४; ३. ५२, ५; ५. १८, २; ७४, ६; ७५, १; ८. २, १३; १३, ६; १९; २२; १४, १; १९, २६; ४४, १८.

स्तोतारः २. २, १२; ६. ३४, ३; ५४, ९; ८. ३२, ७; ३३, १; १०. १०४, ५.

स्तोतारः १. १५६, ३.

स्तोतारं १. १०५, ८; ११२, ११; ३. ४१, ६; ४. १७, १३; ७. ३२, १८; ८६, ४; ८८, ४; ८. ३६, २; ९७, १; ९. ५१, ४.

स्तोतुः १. ५७, ५; ३. १८, ५; ८. ३३, ९; ५२, ९.

स्तोतृऽभ्यः १. ११, ३; ३०, १४; ३३, २; ५८, ८; १२७, ११; २. १, १६; २, १३; ११, २१; १५, १०; १६, ९; १७, ९; १८, ९; १९, ९; २०, ९; ३४, ७; ३८, ११; ३. १०, ८; ४. ३२, ८; ५. ६, १; ८; १०, ७; ७९, १०; ६. ४८, ८; ७. ३, १०; ७, ७; ७९, ४; ८. २, २४; २१, १०; ६४, ५; ७७, ८; ९३, १९; २५–२७; ९. २०, ४; १०६, १३.

स्तोतृणां ३. ५, २; ५. ६४, ४; ६. ४५, २९; ८. १४, ११; १०. २४, ३.

स्तोतॄन् ७. ५५, ३; ९. ५६, ४; १०. ७८, ८.

स्तोत्रं १. ३०, ५; १३८, १; ३. ३१, १४; ६. ३४, ५; ५२, ११; ८. ४५, २१; १०१, ५; १०. १०५, १.

स्तोत्रस्य ५. ५५, ९; ९. ७२, ९.

स्तोत्रे १. १०२, १; १२४, १०; ६. ३५, १; ८. ६०, ६; ९. २०, ७; २१, २; ४०, ५; ४५, ६; ६२, ३०; ६६, २७; ६७, १९; ७२, ८; ९७, ६; १०. १५६, ५.

स्तोत्रेषु ८. ५०, ४.

स्तोभत १. ८०, ९.

स्तोभति १. ८८, ६.

स्तोभतः ८. ५४, १.

स्तोभति १. १६८, ८; ५. ८४, २.

स्तोभतु ८. ९२, १९.

स्तोमः १. ८, १०; १६, ७; २०, १; ५१, १४; १२७, १०; १५६, १; १६५, ११; १५; १६६, १५; १६७, ११; १६८, १०; १७१, २; १७३, १३; १८३, ६; १८४, ५; ६; ३. ५८, १; ४. ३२, १५; ३६, ७; ३७, ३; ४१, १; ५. ४२, १५; १६; ६. ३८, ३; ४५, ३०; ६३, १; ७. २०, ९; २४, ५; ३३, ८; ३४, १४; ६४, ५; ६६, १; ८६, ८; ८. ५, १८; १४, १०; २६, १६; ८७, १; १०. २९, १; १४३, ३.

स्तोमऽतष्टा ३. ३९, १.

स्तोमऽतष्टाः ३. ४३, २.

स्तोमऽतष्टासः १०. १५, ९.

स्तोमं १. १०, ९; १२, १२; १६, ५; २१, १; २७, १०; ४१, ७; ४४, १४; ६१, १; ४; ९४, १; १०९, २; १८४, ४; २. ५, ७; २७, २; ३९, ८; ३. १५, २; ५४, १०; ६०, ७; ६१, १; ४. ४, १५; २२, १; ४४, ६; ५. १, १२; २, ११; ७, १; १३, २; ३५, ८; ४१, २; ४२, २; ५२, ४; ६०, १; ६१, १७; ८१, ५; ६. १०, २; १६, २२; ३५, १; ७. १५, ४; २१, १; ३४, २१; ४०, १; ७३, १; ९३, १; ९५, ५; ९९, ६; ८. १, १४; १५; २, १७; ५, ७; ७, ९; ८, १२; १७; ९, ७; १२, ४; १४; १९, ११; ३३, १५; ३५, ५; ३६, ६; ४३, १६; ४४, २; ४९, ५; ६६, ८; ८५, २; १००, ३; ९. १०८, ७; १०. २३, ६; ३९, १४; ४२, १; ५६, ३; ६१, २५; ६३, ६; ७५, ५; ९२, ९; ९३, १२; १०६, ११; १२७, ८; १६७, ४.

स्तोमऽवर्धनः ८. १४, ११.

स्तोमऽवाहसः १. ५, १; ४. ३२, १२; ८. ४, २.

स्तोमऽवाहसां ८. ९९, १.

स्तोमऽवाहाः ६. २३, ४.

स्तोमस्य ८. ८, ५; २३, १४.

स्तोमाः १. ५, ८; ७, ७; ११, ८; ६. ६०, ७; ७. १९, १०; ८. ५, ३; ८, २२; ९, ८; ६४, १; १०३, ६; १०. ४७, ७; ८५, ८.

स्तोमान् १. १०, ४; ४८, १४; ११४, ९; ११६, १; १२६, १; ७. ३८, ३; ८. २६, ४; १०. ६५, ३.

स्तोमाय ८. ३, ११.

स्तोमासः ३. ५४, १४; ५. २९, ११; ८४, २; ६. ६९, २; ३; ७. ७२, ३; ८. १, २९; ३, १५; ४३, १.

स्तोमे ३. ५४, २; ५. १६, ३; ६. २३, १.

स्तोमेन ५. १४, १; ७५, १; ८. ९, ४; १०. ८८, १०.

स्तोमेभिः १. ९, ३; १३१, २; १३८, २; ४; १३९, ३; २. १३, ५; ३३, ५; ३. ५, २; ३२, १३; ५. १०, ३; १४, ६; ६. २४, ७; ५९, १०; ७. ६२, २; ८०, १; ८. ३, ७; १६; ७, २१; ८, ७–९; १२, २३; २३, २४; ५४, ८; १०. ९९, ११; १२२, ५.

स्तोमेषु २. ११, ३; ३. ४१, ४; ८. ५२, ४.

स्तोमैः १. १३६, ५; १८०, १०; २. ९, ३; ३. ४२, ४; ४. १०, १; ५२, ४; ५. २२, ४; ५६, ५; ६६, ३; ७९, ४; ७. ६७, ३; ७३, ३; ७६, ६; ९६, १; ८. ३, ३; ६, १; ३; ७, १७; १२, ११; ४३, ११; ४४, २७; ५२, ६; ६१, १०; ९. ११४, २; १०. ६४, ७.

स्तोम्यः १. २२, ८; ८. १६, ८.

स्तोम्यं ८. २४, १९; १०. ९६, ६.

स्तोम्यां ६. ६१, १०.

स्तोम्याः १. १२४, १३.

स्तोषत् ५. ३६, ३; ८. ८१, ५.

स्तोषं १. १८७, १.

स्तोषाणि १०. ८८, ३.

स्तोषाम १. ५३, ११; ६. ५५, ४; ७. २, २.

स्तोषि १०. २२, ४.

स्तौत् ७. ४२, ६.

स्तौनाः ६. ६६, ५.

स्तौलाभिः ६. ४४, ७.

स्त्रियः १. १६४, १६; ५. ३०, ९; ७. ५५, ८.

स्त्रियं ४. ३०, ८; ७. १०४, २४; १०. ३४, ११.

स्त्रियाः ८. ३३, १७.

स्त्री ५. ६१, ६; ८. ३३, १९; १०. ८६, ६.

स्त्रीभिः १०. २७, १०.

स्त्रैणानि १०. ९५, १५.

स्थ १. १५, २; १३९, ११[3]; १७१, २; ४. ३४, ६; ३६, ७; ५. ६०, ६; ६. ५०, ७; ५१, १५; ५२, १३; ७. ४३, ४; ८. ३०, २; १०. ९, १; १८, ६; ३०, १२; ३६, १०; ६१, २७; ६३, २.

स्थ २. २९, ४; ५. ५७, २; ६१, १; ७. १०३, ७; ८. ५५, ४; ६७, ५; १०. ९४, ११; ९७, ९.

स्थः १. १७, २; ४७, ७; १०८, ८–११; ३. ५४, १६; ५. ७३, १; ८. १०, १; ५; ३८, १; ९. १९, २; १०. १०६, २.

स्थुः १. १०८, ३; १५७, ६[2]; २. ३०, ६; ५. ७२, २; ६. ६९, ६; ८. ७३, ४; १०. ४०, ६.

स्थनं १. १०५, ५; ५. ८७, ६; ८. ३०, ४; ९. ६९, ८; १०. ६३, ६.

स्थन ५. ५९, ३; ८. १८, १५; १०. ९४, १०[?]; ९७, ९.

स्थविरः १. १७१, ५; १०. १०३, ५.

स्थविरं १. ५४, ८; ४. १८, १०; २०, ६; १०. ५१, १.

स्थविरस्य ३. ४६, १; ६. १८, १२; ३७, ५; ४७, ८; ७. ९३, २; १००, ३.

स्थविरा १. १८१, ७.

स्थविराय ६. ३२, १.

स्थविरासः ७. ६७, ४.

स्थविरेभिः ६. १, ११; ७. २४, ४.

स्थऽशः २. ३८, ८.

स्थाः १. ८०, १४; २. २७, ४; ६. २४, ९; १०. ३५, ९; ८८, ४.

स्थाः ४. ३०, १२.

स्थाःऽरंश्मानः ५. ८७, ५.

स्थाणुं १०. ४०, १३.

स्थात् १. ६८, १; २. ३, १०; १५, ७; ३. १५, ६; ३६, ९; ५. ५३, ९; ७. ८७, ६.

स्थात ५. ५३, ८; ७. ३४, ५; ८. २०, १.

स्थातः १. ३३, ५; ६. ४१, ३; ४९, ६; ८. २४, १७; ३३, १२; ४६, १.

स्थातं १०. १०६, २.

स्थाता ३. ४५, २.

स्थातां १. ७०, २.

स्थातारः ५. ८७, ६.

स्थातारा १. १८१, ३.

स्थाताराऽइव १०. ५९, १.

स्थाति २. ३१, ३.

स्थातुः १. ५८, ५; ६८, १; ७०, ४; १५९, ३; २. ३१, ५; ४. ५३, ६; ६. ५०, ७; ७. ६०, २; १०. ६३, ८.

स्थातॄन् १. ७२, ६.

स्थात्रे १. १६४, १५.

स्थाथः ४. ४६, ४; ८. ५, २८.

स्थानं ५. ७६, ४; ७. ७०, १.

स्थानानि ७. ७०, ३; ८. ५९, ६.

स्थापयंति १०. १०२, १०.

स्थापयसे १०. १२०, ७.

स्थां ९. ८५, ११.

स्थां २. २७, १७; २८, ११; २९, ७.

स्थामं १. १३९, ४.

स्थाविरीः ९. ८६, ४.

स्थिरः १. १०१, ४; २. ४१, १०; ८. ३३, ९; ९२, २८.

स्थिरऽधन्वने ७. ४६, १.

स्थिरऽपीतं १०. ७१, ५.

स्थिरं १. ३७, ९; ३९, ३; ६४, १५; १२७, ३; ३. ३५, ४; ५. ३०, ४; ८. ३२, १४; १०. ६१, २०; ११७, २; १२०, ४; १३४, २.

स्थिरस्यं ५. ५२, २.

स्थिरा १. ३९, २; १२७, ४; १६७, ७; २. ३३, १४; ४. ४, ५; ७, १०; ७. ५६, ७; ८. २०, १; १२.

स्थिराऽइंव १०. ११६, ६.

स्थिराः १. ३८, १२; ८. ६६, २.

स्थिराणि १. १२७, ४; ८. १४, ९; १०. ८९, ६.

स्थिराय ३. ३०, २; ६. २४, ८; १०. ९६, ७.

स्थिरे ८. ४५, ४१.

स्थिरेभिः २. ३३, ९.

स्थिरैः १. ८९, ८.

स्थिरौ ३. ५३, १७.

स्थिविऽभ्यः १०. ६८, ३.

स्थिविमंतः १०. २७, १५.

स्थुः १. २४, ७; १६७, ९; ५. १५, ३; ७. १८, ३; १०. ५७, १.

स्थूणा ५. ६२, ७; ८. १७, १४.

स्थूणाऽइव १. ५९, १; ५. ४५, २.

स्थूणां १०. १८, १३.

स्थूरं ६. १९, १०; ८. १, ३४; ४, १९; २१, १; २४, २९; ५४, ८; १०. १५६, ३.

स्थूरयूपऽवत् ८. २३, २४.

स्थूरयोः ६. २९, २.

स्थूरस्यं ४. २१, ४.

स्थूरिं १०. १३१, ३.

स्थेयाम ६. ४७, ८; ७. ९५, ५; ८. २७, २०.

स्नातः १. १०४, ३.

स्नाती ५. ८०, ५.

स्नात्वीः १०. ७१, ७.

स्नीहितीपु १. ७४, २.

स्नुना ४. २८, २; ८. ७, ७; ९. ९७, १६; १९.

स्नुऽभिः ५. ६०, ७; ८७, ४; ७. ८८, ३; ८. ४६, १८; ९. १०७, ८.

स्नेहयंत् ९. ९७, ५४.

स्नेहितीः ८. ९६, १३.

स्नोः ४. २७, ४.

स्पद् ५. ५९, १; ८. ६१, १५; १०. ३५, ८.

स्पंदने ३. ५३, १९.

स्परत् १. १६१, ५.

स्परसे ८. २०, ८.

स्पुरिति स्पः ९. ७०, १०.

स्पर्तं ७. ७१, ५.

स्पर्धंते ६. १४, ३; ७. ८५, २; ९. ९४, १.

स्पर्धमानाः १. ३३, ५.

स्पर्धमाने इति ७. ९३, ५.

स्पर्शयस्व १०. ११२, ३.

स्पशः १. २५, १३; ३३, ८; ४. ४, ३; ६. ६७, ५; ७. ६१, ३; ८७, ३; ८. ४७, ११; ९. ७३, ४; ७; १०. १०, ८.

स्पशं ४. १३, ३.

स्पार्हः ४. १, १२; ४७, १.

स्पार्हं १. ३१, १४; ७. ८१, ३; ८. ४५, ४०; १०. ४९, १०; ५५, ६.

स्पार्हया ७. ७२, १.

स्पार्हऽराधाः ४. १६, १६.

स्पार्हऽवीरं ५. ५४, १४.

स्पार्हऽवीराः ७. ९१, ५.

स्पार्हस्य ८. २४, ८.

स्पार्हा १. १२३, ६; १३५, २; २. २३, ९; ४. १, ६; ७.

स्पार्हाः ७. १५, ५; ९. १०२, ५; १०. २, ६; २६, १; ६८, ३.

स्पार्हाणि ७. ५९, ६.

स्पार्हाभिः ७. ५८, ३; ८४, ३.

स्पार्हे २. १, १२; ७. ५६, २१.

स्पाशयस्व १. १७६, ३.

स्पृधन् ६. ६७, ९.

स्पृधसे ५. ६४, ४.

स्पृणवाम ५. ४४, १०.

स्पृणुहि १०. ८७, ७.

स्पृतं १०. ३९, ६.

स्पृधः १. ८, ३; १७४, ५; १७९, ३; २. ११, १९; ५. ४४, ७; ५५, ६; ६. ५, ६; ६, ६; २०, ९; २५, २; ९; ४५, १८; ४९, १५; ८. १४, १३; ९२, ३२; ९९, ५; ६; ९. ७, ५; २०, १; १०. १८, ९; १००, १२; ११३, ४; १६७, २.

स्पृधानं ३. ३१, ४.

स्पृधां १. ११९, १०, १७४, १०.

स्पृधि ७. ८२, ९.

स्पृधि ५. ३, ९; ८. ६६, १४.

स्पृशः ४. ३, १५; ४, २; ७. २, १; ८. ९६, ११; १०. ८७, २.

स्पृशतं १०. ७०, ५.

स्पृशंति १. ६२, ११.

स्पृशंति १. ३६, ३.

स्पृशामसि १०. १३७, ७.

स्पृशामि १०. १२५, ७.

स्पृहयत्ऽवर्णः २. १०, ५.

स्पृहयंति ८. २, १८.

स्पृहयाय्यः ६. १५, १२.

स्पृहयाय्यस्य ८. ९७, १५.

स्पृहयाय्याणि ६. ७, ३.

स्पृहयेत् १. ४१, ९.

स्फरीः ६. ६१, १४.

स्फातिं १. १८८, ९.

स्फिग्यं ८. ४, ८.

स्फिग्या ३. ३२, ११.

स्फिरं ८. १, २३.

स्फुर ४. ३, १४.

स्फुरत् १. ८४, ८.

स्फुरंति १०. ३४, ९.

स्फुरान् ६. ६७, ११.

स्फूर्जयन् १०. ८७, ११.

स्म १. १२, ५; ८; १५, १०; २६, ३; २८, ६; ३७, १५^{२}; ४२, २; ५१, १२; १०२, ३; ५; १०४, ५; १२७, ६; ९; १२८, ५; १२९, २; ३; १३३, ७; १६९, ३; ५; १७३, ११; १२; १८०, ७^{२}; ८; २. १२, ५; ३१, २; ३. ३०, ४; ६२, १; ४. ३, १०; १०, ७; १६, १७; २९, २; ३१, ७–९; ३८, ४–६; ८^{२}; ४०, ३; ४३, ३; ५. ७, ४^{२}; ५; ७; ८; ९, ३–५; २३, ४; ४५, ४; ५२, ८; ९; ५३, ५; ५४, ६; ५६, ७; ६. २, २; १२, ५; १५, ९; १७, १४; २५, ७; ४४, १८^{२}; ४६, १०; १२; ६५, ४; ६६, ६; ७. ३, २; १५, १३; २१, ९; ३२, १५; ५६, २२; ८३, ५; ८८, ६; ८. १, २१; ७, २१; २१, १०; २४, ६; २५, १५; २७, ४; १४; ४४, ११; ६०, १०; ८६, ३; ९२, २६; ९. २०, २; ८७, ६; ९; १०. १२, ५; २७, २४; २९, ८; ३३, १; ८६, १०; ८७, २३; ९५, ५^{२}; ८; ९६, १०; १०२, २; ४; ६; १३४, २; १३६, ७; १७८, ३.

स्मः ८. २१, ६.

स्मः ८. १०२, ३.

स्मत् १. ५१, १५; १००, १३; १८६, ६; ८; २. ४, ९; ५. ४१, १५; १९; ८७, ८; ७. ३, ८; ८. १८, ४; २०, १८; २६, १९; १०. ६१, ८.

स्मत्ऽइभं १०. ४९, ४.

स्मत्ऽइष्टाः ७. ८७, ३.

स्मत्ऽऊध्नीः १. ७३, ६.

स्मत्ऽदिष्टयः ७. १८, २३.

स्मत्ऽदिष्टिः ३. ४५, ५.

स्मत्ऽदिष्टीन् ६. ६३, ९.

स्मत्ऽपुरंधिः ८. ३४, ६.

स्मदभीशू इति स्मत्ऽअभीशू ८. २५, २४.

स्मदिष्टी इति स्मत्ऽदिष्टी १०. ६२, १०.

स्मद्रातिऽसाचः ८. २८, २.

स्मयते १. ९२, ६.

स्मयंत १. १६८, ८.

स्मर्यमानः २. ४, ६.
स्मर्यमानाभिः १. ७९, २.
स्मर्यमानासः ४. ५८, ८.
स्मयेते इति ३. ४, ६.
स्मराथः १०. १०६, ९.
स्मरेथां ७. १०४, ७.
स्मसि १. २९, १; ३७, १५; ५. ७४, ६; ८. १८, २२; ४६, १; ९. ९७, २७.
स्मसि १. ५७, ५; २. ४१, १६; ६. ५४, ९; ८. १८, १९; ३२, ७; ४७, ८; ४८, ८; ६६, १३; ९२, ३२.
स्य ४. १६, २; ५. ८५, ८; ६. ४, १; ९. ९५, ५; ९७, १८.
स्यः १. १६१, ४; २. ३१, ३; ४; ३२, ७; ३६, ५; ३८, १; ४. ३८, ७; ४०, ४; ४५, १; ५. ३०, १; ५६, ७; ६. २, ३; ५०, १३; ७. ८, २; २३, ३; ६०, २; ६७, ७; ६८, ९; ६९, ५; ८. २५, १९; २७, १२; ६४, ७; ९. ३, १०; ३८, १; ४–६; ६२, १३; ८४, ४; ८७, ४; ८९, १; ९६, १५; ९७, ४६; ९८, २; १०८, ५; १०. ८६, २२; ९२, १२; १७६, ३.
स्यतं ६. ७४, ३; १०. १४३, २.
स्यतां २. ४०, ४.
स्यति १०. ६१, २०.
स्यतु १. १४२, १०; २. ३, ९.
स्यध्वं १०. ३०, ११.
स्यंता १०. २२, ४.
स्यंति १. ८५, ५.
स्यंदते ९. ८०, ३.
स्यंदंतां ५. ८३, ८.
स्यंदमानाः १. ३२, २.
स्यंदयध्यै ४. २२, ७.
स्यंदस्व ९. ६७, २८.
स्यंद्रः ६. १२, ५.
स्यंद्रं १०. ४२, ५.
स्यंद्रा १. १८०, ९.
स्यंद्राः ५. ५२, ८.
स्यंद्रासः ५. ५२, ३; ८७, ३.
स्यन्नाः ५. ५३, ७.
स्यस्व १. १०१, १०.
स्यस्वेति स्यस्व ३. ४, ९.
स्या १. ८८, ६; १०४, ५; ११९, ९; १६५, ६; १७८, १; १८१, ८; ४. ५२, १; ५. ६, ४; ६. ६१, ७; ६५, १; ७. ७५, ४; ८०, २; ९५, ४; ८. १८, ७; २६, १८; ४६, ३३.
स्याः ८. ४४, २३.
स्याः १. १७४, १०; ४. १६, १८; ६. ३३, ५; ७. १, ८; ९; १०. ११, ९; ६९, ६.
स्यात् १. १७, ६; ३. १, २३; ७. ३४, २१; ८. २, १३; १९, २६.
स्यात् १. ३८, ४; १६७, १०; १८२, ८; ३. ३९, ८; ६२, ३; ६. ६८, ६; ७; ८. १४, १; १०. ३१, ४; ११७, ७.
स्यार्त ५. ८७, ९.
स्यातन १. ३८, ४.
स्यातं १. १२०, ७; ३. ३८, ९.
स्यातां १. १०४, ३; ४. ४१, ६.
स्यां ६. ५०, ९; ८. १४, २; १९, २५; ४४, २३.
स्यां १. ११६, २५; ३. १५, १; ६. ५०, ९; ६३, ११; ७. १, १३; ८. ४४, १८.
स्याम १. ४, ६; २. ११, १; १३; ५. ३१, १३; ३८, ५^2; ५३, १४; १५; ६५, ५; ७. १८, ३; २०, ८; ४०, १; ६६, १३; ८१, ४; ८. १९, ७; ३५; ४४, २४; ६३, १०; ९. ६१, २४; ९८, ५; १०. ३८, २; ६६, १२; १२६, ४.
स्याम १. २४, १५; ५१, १५; ७३, ८; ९४, १३; १५; ९८, १; १०५, १९; १२१, १५; १५०, ३; १६४, ४०; १७८, ५; १८०, ९; १८५, ४; २. २, १२; ८, ६; ११, १२; १८, ८; २४, १५; २७, ७; १६; २८, २; ३; ३८, १०; ३. १, १६; २१; ३०, १८; ३९, ७; ८; ५५, २२; ५९, ३; ४. ८, ५; १६, २१; १७, ९; २९, ५; ४१, १०; ११; ५०, ६; ५१, १०; ११; ५. ४, १; ८; ६, ८; २०, ४^2; ४२, १७; ४५, ११; ४९, ४; ५४, १३; ६२, ९; ७०, २; ८५, ८; ६. १९, १३; २६, ८; ३३, ५; ४७, १२; ५२, ५; ७१, २; ६; ७. १, २०; २५; ४, ४; ७; १४, ३; १७, ७; १९, ७; २१, ९; ३४, २४; २५; ३७, ४; ४१, ३; ४^2; ५; ४८, २; ५२, १; ५४, २; ५६, २४; २५; ६०, १; ६६, ९; ८७, ७; ९२, ४; ८. ४३, ३०; ४८, २१; ५३, ७; ९. ३५, ३; ८६, ३८; ८९, ७; ९५, ५; १०. २२, १२; २९, २; ३१, १; ३५, १४; ३६, १२; ६४, ११; १३२, २; १४८, ३.
स्यालात् १. १०९, २.
स्युः ८. ४४, २३.
स्युः ६. २८, १.
स्युरिति स्युः २. ४, ९; ८. ७०, ५.
स्युरिति स्युः १. २४, ७; १२३, १३; ६. ६३, १०; १०. २०, ८; ८९, १५.
स्यूतं १. ३१, १५.
स्यूमऽइव ३. ६१, ४.
स्यूमऽगभस्तिः १. १२२, १५.
स्यूमऽगभस्ति ७. ७१, ३.
स्युमऽगृभे ६. ३६, २.
स्यूमना १. ११३, १७.
स्युमन्यू इति १. १७४, ५.
स्यूमऽरश्मये १. ११२, १६.
स्यूमऽरश्मौ ८. ५२, २.
स्योनऽकृत् १. ३१, १५.
स्योनं १०. ७०, ८; ८५, २०; ११०, ४; ८.
स्योनऽशीः १. ७३, १; ७. ४२, ४.
स्योना १. २२, १५; १०. ८५, ४४.
स्योनात् ४. ५१, १०.
स्योनान् १०. ७३, ७.
स्योनां ५. ४, ११.
स्योने ६. १६, ४२.
स्रक्तीः ७. १८, १७.
स्रके ९. ७३, १.
स्रकेषु ७. ५५, २; ८. ७२, १५.
स्रक्षु ५. ५३, ४.
स्रजः ८. ५६, ३.
स्रजं ४. ३८, ६; ८. ४७, १५.

स्रव ८. ९१, ३; ९. ८, ८; ३९, २; ५५, १; ५६, ४; ६१, १; १२; ६२, ९; २३; ८५, १; ९७, १९; २१; ४८; १०७, २.
स्रवतः १. ७१, ७; १९०, ७; ३. ४६, ४; ७. १८, २४; ६७, ८; १०. ४९, ९; १०८, ४.
स्रवथे ३. १, ७.
स्रवंति ८. ४९, २.
स्रवंति ४. ५८, ६; १०. ११३, ५.
स्रवंतीः १. ३२, १४; १७४, ९; १०. १०४, ८.
स्रवंतु १०. ९, ४.
स्रवितवे ४. ३, १२; १९, ८.
स्रवितवै ७. २१, ३.
स्रवेत् १. १२९, ६[२].
स्रसेम ६. ११, ६.
स्रामं १. ११७, १९.
स्रामात् ८. ४८, ५.
स्रिधः १. ३६, ७; ४८, ८; ३. ९, ४; १०, ७; ७. ८१, ६; ८. १८, ७–९; ७९, ९; ९४, ७; ९. २७, १; ६३, २८; ६६, २२; १०. २५, ७; १२६, ५.
स्रिधः १. १२९, ११; ९. ७१, ८.
स्रिधत् ७. ३४, १७.
स्रिधं ८. १८, १०.
स्रुक् ६. ११, ५; ८. २३, २२.
स्रुचः १. १४४, १; ५. २१, २; ४१, १२; ८. ६०, २; १०. ११८, २.
स्रुचा १. ८४, १८; ५. १४, ३; १०. १७, १३; ११८, ३.
स्रुचाऽइव १. ११०, ६; १६२, १७.
स्रुचिऽइव १०. ९१, १५.
स्रुतर्यः ६. २४, ४; ९. ७८, २.
स्रुता ८. ९१, १.
स्रुतिः १. ४६, ११.
स्रुतिं २. १३, १२; १०. ३२, ७.
स्रुती इति १०. ८८, १५.
स्रुतेः १. ४२, ३.
स्रुवाऽइव १०. ९६, ९.
स्रुवेण १. ११६, २४; १२१, ६.
स्रेधत ७. ३२, ९.
स्रेधति ५. ५४, ७.
स्रेधंतं ७. ३२, २१.
स्रेवयंतः ७. १८, ८.
स्रोतः १. ९५, १०.
स्रोतसा १. ५१, ११.
स्रोत्याः १०. १०४, ८.
स्रोत्याभिः ३. ३३, ९.
स्वऽइर्दुहव्यैः १. १२१, ६; १७३, २.
स्वऽएतवः ५. ४१, ९.
स्वः २. ५, ७; ६. ७५, १९; ७. ८६, ६; ८. ७०, ११; १०. १८, १.
स्व॑ः १. ५०, ५; ५२, ९; ६६, ५; ६९, ५; ७०, ४; ५; ७१, २; १०५, ३; ११२, ५; १३१, ३; १४८, १; १६८, २; २. २, ७; ८; १०; ८, ४; २१, ४; ३५, ६; ३. २, ७; ३४, ८; ६१, ४; ४. ३, ११; १०, ३; १६, ४; २३, ६; ४०, २; ४५, २; ५. ४४, २; ४५, १; ५४, १५; ६६, २; ८०, १; ६. २९, ३; ६०, २[२]; ७२, १; ७३, ३; ७. १०, २; ३४, १९; ८१, ४; ८८, २; ९०, ६; ८. ३, १३; १५, २; १२; ४६, ८; ४९, ८; ७६, ४; ९८, ३; ९. ४, २; ७, ४; ४८, ४; ५९, ४; ६१, १८; ७४, १; ८६, १४; ९०, ४; ९१, ६; ९८, ८; ११३, ७; १०. २०, २; ४३, ४; ९; ६१, १४; ६५, १; १४; ६६, ४; ९; ८८, २; १२४, ६; १३६, १; १५४, २; १९०, ३.
स्वःऽगे १०. ९५, १८.
स्व॑ःऽचक्षाः ९. ९७, ४६.
स्व॑ःऽचनाः ९. ८४, ५.
स्वःऽजित् ९. २७, २; ७८, ४.
स्वःऽजितं १०. १६७, २.
स्वःऽजिते २. २१, १.
स्वःऽजेषे १. १३२, २.
स्वःऽदृक् ७. ५८, २.
स्वःऽदृशः १. ४४, ९; १५५, ५; २. २४, ४; ७. ३७, २; ८३, २; ९. १३, ९; ७६, ४.
स्वःऽदृशं ३. २, १४; ५. २६, २; ७. ३२, २२; ९. ६५, ११.
स्वःऽदृशा ५. ६३, २.
स्वःऽनरः ५. ५४, १०.
स्व॑ःऽनरं २. २, १; ५. ६४, १; ६. १५, ४; ८. ३, १२; १२, २; १९, १; ९. ७०, ६; १०. ६५, ४.
स्व॑ःऽनरात् ४. २१, ३.
स्व॑ःऽनरे ५. १८, ४; ८. ६, ३९; ६५, २; १०३, १४.
स्व॑ःऽपतिः ८. ४४, १८.
स्व॑ःऽपतिं ८. ९७, ११.
स्व॑ःऽपती इति स्व॑ःऽपती ९. १९, २.
स्व॑ःऽभानुः ५. ४०, ५.
स्व॑ःऽभानोः ५. ४०, ६; ८.
स्व॑ःऽमीळ्हस्य १. १६९, २.
स्व॑ःऽमीळ्हे १. ५६, ५; ६३, ६; ४. १६, १५.
स्व॑ःऽमीळ्हेषु १. १३०, ८; ८. ६८, ५.
स्वःऽयवः ३. ३०, २०.
स्व॑ःऽवत् १. १७३, १; १८५, ३; ६. १९, ९; ३५, २; ४७, ८; १०. ३६, ३.
स्व॑ःऽवति १०. ६३, १५.
स्व॑ःऽवती १. १६८, ७; ५. ३४, १; १०. ११, ३.
स्व॑ःऽवतीः १. १०, ८; १२९, ८; ५. २, ११; ८. ४०, १०; ११.
स्व॑ःऽवतीं १. १३६, ३.
स्व॑ःऽवते १. ५९, ४.
स्व॑ःऽवंतः ६. ५०, २.
स्व॑ःऽवान् ६. २२, ३; ३७, १; ८. ९७, १.
स्वःऽवित् १. ९६, ४; ३. ३, १०; ८. ४८, १५; ९. ८६, ३; १०९, ८.
स्वःऽविदः ९. २१, १; ९७, ३९; १०१, १०; १०६, १; ९; १०७, १४; १०८, २; १०. ४३, १; ६५, १४.
स्वःऽविदं १. ५२, १; २. २३, ३; ३. ३, ५; २६, १; ५१, २; ५. ४४, १; ८. १३, ५; ९. ८, ९; ८४, ५; १०६, ४; १०. ५६, ६; १०७, ४.
स्वःऽविदा ६. ३९, ४; ७. ६७, ३.
स्वःऽविदा ८. ८, ७.
स्वःऽविदि १०. ८८, १.

स्व॒ःऽवि॑दे ९. ९४, २.
स्व॒ःऽसाः १. १००, १३; २. १८, १; ३. ३४, ४; ७. ९७, ७; ९. ९६, १८; १०. १२०, ८.
स्वं॑ःऽसाता १. १३१, ६; ४. १६, ९; ६. १७, ८; ३३, ४; ९. ८८, २; १०. ९९, ३.
स्व॒ःऽसां १. ६१, ३; ९१, २१; ५. ४५, ११; १०. ८, ६; ४७, ५.
स्वऽक्षं॑त्रं १. ५४, ३; ५. ३५, ४.
स्वऽक्षं॑त्रया ५. ४८, १.
स्वऽक्षं॑त्रेभिः १. १६५, ५.
स्वऽगू॑र्ता ४. १९, १०.
स्वऽगू॑र्ताः १. १४०, १३; ६. ६८, ४; १०. ९५, ७.
स्वऽगो॑पा १०. ३१, १०.
स्वऽचं॑द्रं १. ५२, ९.
स्व॒ज॒ध्वं॒ १०. १०१, १०.
स्व॒जं॑ते॒ १०. ४३, १.
स्वऽजं॑न्मना ७. १, १२.
स्व॒ऽजाः १. १६८, २.
स्व॒जा॑ते॒ १०. १०, १३.
स्व॒ऽजां १. १२१, २.
स्व॒जा॒म॒हे॒ १०. १३३, २.
स्वऽजें॑न्यं ५. ७, ५.
स्वऽतं॑वः १. १५९, २.
स्व॒ऽत॒व॒ः ६. २२, ६.
स्वऽतं॑वसः १. ६४, ७; ८५, ७; १६६, २; १६८, २; १८६, १०.
स्व॒ऽत॒व॒सः ७. ५९, ११.
स्वऽतं॑वसे ६. ६६, ९; ९. ११, ४.
स्वऽतं॑वान् ४. २, ६; २०, ६.
स्व॒द॒ ३. १४, ७.
स्वदं॑थः ८. ५, ३६.
स्वदं॑ति ७. २, २; ८. ५०, ५; ९. ६२, ५.
स्वदं॑तु १०. ११०, १०.
स्व॒दं॑ते॒ २. १, १४.
स्व॒द॒य॒ १०. ११०, २.
स्व॒द॒यं॑त॒ ९. १०५, १.
स्व॒द॒यं॑ति ८. ४९, ५.
स्वदं॑स्व ३. ५४, २२; ९. ७४, ९; ९७, ४४.
स्वदा॑ति १०. ७०, १०.
स्वदा॑मि १. ११९, २.
स्व॒दा॒ऽव॒न् ८. ५०, ५.
स्व॒दि॑तं ९. ६७, ३१.
स्व॒धया॑ १. ६४, ४; १०८, १२; १५४, ४; १६४, ३८; २. ३, ८; ३. ४, ७; १७, ५; ३५, १०; ४. १३, ५; २६, ४; ४५, ६; ५८, ४; ५. ३२, ४; ७. ४७, ३; ७८, ४; ९. ६८, ४; ७१, ८; १०. १४, ३; ७; १५, ३; १२; १४; २७, १९; ८८, १; १२४, ८; १२९, २.
स्व॒धयो॑ः ९. ८६, १०.
स्वऽध॑र्मन् ३. २१, २.
स्व॒धा १. १६५, ६; १७६, २; ५. ३४, १; ६. २, ८; ८. ३२, ६; ९. ११३, १०; १०. १२९, ५.
स्व॒धाः १. १४४, २; ८. ३२, १९; ९. १०३, ५; १०. ३७, ५.
स्व॒धा॒ऽप॒ते॒ ६. ४४, १.
स्व॒धाभि॑ः १. ५१, ५; ९५, ४; ११३, १३; १६४, ३०; १८०, ६; ३. २६, ८; ५. ६०, ४; ७. ३४, १८; १०४, ९; ८. १०, ४; ६; ९. ९२, ४; ९५, १; १०. १५, १३; १६, ५; १७, ८.
स्व॒धां १. ६, ४; ३३, ११; ८८, ६; १६५, ५; १६८, ९; २. ३५, ७; ३. ५१, ११; ४. ३३, ६; ५२, ६; ७. ८, ३; ५६, १३; ८. २०, ७; ८८, ५.
स्वधा॑ऽवः १. १४४, ७.
स्व॒धा॒ऽव॒ः १. ३६, १२; ६३, ६; १४७, २; ३. २०, ३; ३५, ३; ४१, ८; ४. १०, ६; २०, ४; ५. ३, ५; ६. १७, ४; २१, ३; ५८, १; ७. ८६, ४; ८; ८८, ५; १०. ११, ८; ८१, ५; १४२, ३.
स्व॒धाऽवं॑तः ८. ४४, २०.
स्व॒धा॒ऽव॒न् ५. ३, २; ८. ४९, ५.
स्व॒धा॒ऽवं॑त॒ः ७. ३७, २.
स्व॒धाव॑री॒ इति॑ स्व॒धाऽवं॑री ७. ३१, ७.
स्व॒धाऽवा॑न् १. ९५, १; ४; १७३, ६; २. २०, ६; ४. ५, २; १२, ३; ७. २०, १; १०. ३१, ८; ४२, ९.
स्व॒धा॒ऽअ॑न्नं ५. ३२, १०; ७. ४६, १.
स्वऽधि॑तिः १. १६२, १८; २०; ३. ८, ६; ११; ५. ३२, १०; ७. ३, ९; ८. १०२, १९; ९. ९६, ६; १०. ८९, ७; ९२, १५.
स्वधि॑तिःऽइव ५. ७, ८.
स्वऽधि॑तिं २. ३९, ७; ३. २, १०.
स्वधि॑तिऽवान् १. ८८, २.
स्वऽधि॑तौ १. १६२, ९.
स्वऽधै॑नवानां ८. ३२, २०.
स्व॒नः १. १४३, ५; ५. ८७, ५; ९. ४१, ३; ५०, १; ७०, ६; १०. ७५, ३.
स्व॒नत्ऽरं॑थः ८. १, ३२.
स्व॒न॒य॒त् १०. ३, ६.
स्व॒नये॑न १. १२६, ३.
स्व॒नाः १०. ३, ५.
स्व॒नात् १. ३८, १०; ५२, १०; ९४, ११; ६. २७, ४; ९. २९, ५; १०. २७, ५.
स्वनि॑ ६. ४६, १४; ९. ६६, ९.
स्व॒ने ५. ६०, ३.
स्व॒प॒ ७. ५५, २.
स्वपं॑ःऽतमः ४. १७, ४.
स्वपं॑ःऽतमं १. ६१, ६.
स्वऽप॑तिः १०. २७, ८; ३१, ४; ४४, १.
स्व॒पन् ५. ४४, १३.
स्व॒पं॑तः १०. १६४, ३.
स्व॒ऽपूभि॑ः ७. ५६, ३.
स्वप्नः॑ ७. ८६, ६.
स्व॒प्न॒ऽनं॑शनः १०. ८६, २१.
स्वप्न॑स्य १. १२०, १२.
स्वप्ना॑य ८. २, १८.
स्वप्ने॑ २. २८, १०.
स्वप्ने॑न २. १५, ९; १०. १६२, ६.
स्व॒ब्दीऽइ॑व ८. ३३, २.
स्वऽभा॑नवः १. ३७, २; ८२, २; ५. ५३, ४.
स्व॒ऽभा॒न॒व॒ः ८. २०, ४.
स्वऽभा॑नवे ५. ५४, १; ६. ४८, १२;

स्वभानो इतिं स्वऽभानो ६. ६४, ४.
स्वभिष्टिऽसुंम्नः ६. २०, ८.
स्वभूंतिऽओजाः १. ५२, १२.
स्वं १. ४६, ९; ५८, २; ७५, ५; १२८, १; ३. ७, ६; ३१, १०; ५. ५८, ७; ५९, १; ६. २०, ११; २८, २; ४१, १; ७. २३, २; ५६, २४; ८२, ६; ८. ७२, १४; ९. ६३, ६; १०. १, ३; १२, १; १३, २; ५६, २; ८५, ३०.
स्वऽयंतासः १. १६६, ४.
स्वयं १. ८७, ३; १२२, ९; १२९, ६; ८; १५८, ५; २. ३५, १४; ४. १८, ५; १०; ५०, ८; ५. १२, ५; ४४, ८; ४६, १; ५५, २; ८७, २; ६. ५१, ७; ७. ८, ५; ५६, ११; ८. ४, १२; ६६, १५; ९. २१, २; ४७, ४; १०. ७, ६; २७, १२; २८, ११; ५०, ६; ८१, ५; ६; ९१, ५; १२५, ५.
स्वयंऽजाः ७. ४९, २.
स्वयंऽभूः १०. ८३, ४.
स्वऽयशाः ७. २२, ५; १०. ४९, ११.
स्वयंशःऽतरः ३. ४५, ५; ५. १७, २.
स्वयंशःऽतरं ५. ८२, २; ८. ६०, ११.
स्वयंशःऽभिः १. ९५, ९; १२९, ८.
स्वऽयंशसः १. १३६, ७; ७. ८५, ३; ८. ६७, १३; १०. ७५, ९; ७७, ५.
स्वऽयंशसं १. ९५, २; ९. ९८, ६; १०. ९२, १४; १०५, ९.
स्वऽयंशसे १. १२९, ३; ५. ४८, १.
स्वऽयंशाः १. ९५, ५; ७. ३७, ४; १०. ९२, ९.
स्वया ५. ५८, ५; ७. ३, ९; ८६, २.
स्वऽयावन् ८. २५, १२.
स्वऽयुः २. ४, ७; ३. ४५, ५.
स्वऽयुंक्ताः १. १६८, ४.
स्वयुंक्तिऽभिः १. ५०, ९; ११९, ४.
स्वयुक्ऽभिः १०. ६७, ८; ८९, ७.
स्वयुग्वंऽभिः ९. १११, १.
स्वऽयुजंः १०. ७८, २.
स्वर १. १०, ४; ८. १३, २७; ९. ९७, ३.
स्वरंणं १. १८, १.
स्वरंति १. १५१, ५; ५. ५४, २; १२; ८. ३३, २.
स्वरंति ९. ८५, ३.
स्वरंतु ८. १३, २८.
स्वरंवः ३. ८, ६; ९; १०; ४. ५१, २.
स्वऽराजः १. १८१, २; २. २८, १; ३. ४६, १; ५. ५८, १; ७. ६६, ६; ८. ९४, ४; १०. १२०, ८.
स्वऽराजं १. ३६, ७; ३. ४९, २; ८. ६१, २; ८१, ४.
स्वऽराजें १. ५१, १५; ७. १०१, ५; ८. १२, १४.
स्वऽराज्यं १. ८०, १–१६; ८४, १०–१२; २. ८, ५; ५. ८२, २; ८. ९३, ११.
स्वऽराज्ये ५. ६६, ६.
स्वऽराट् १. ६१, ९; ३. ४५, ५; ७. ८२, २; ८. ४६, २८; १०. १५, १४.
स्वराति ८. ६९, ९.
स्वरिंतारः १. १६६, ११.
स्व१रिति स्वंः १. १४, ४; ४६, ३; ५२, १३; ८३, ४; १२९, २; १३१, २; २. २४, ३; ३. ३१, १९; ७. ४४, १; ६६, ९; ८. ५०, ८; ७२, १५; ८९, ४; ९. ९, ९; ७६, २; १०. २७, २४; ३६, १; ६८, ९; १०७, ८; १२१, ५; १६७, १; १८९, १.
स्वरीणां १०. ६८, ७.
स्वरुंः ४. ६, ३; ८. ४५, २.
स्वरुं १. ९२, ५.
स्वरूंणां ७. ३५, ७.
स्वरे ८. ७२, ७.
स्वरेंण १. ६२, ४.
स्वऽरोंचिः ३. ३८, ४.
स्वऽरोंचिषः ५. ८७, ५.
स्वरौं १. १६२, ९.
स्वर्थे इति सुऽअर्थे १. ९५, १.
स्वर्यः १. ६२, ४.
स्वर्यें १. ३२, २; ६१, ६; १२१, ४; ४. १७, ४; ५. ३०, ८; ७. १०४, ४; १०. १७७, २.
स्वऽवंसुः ५. ४४, ७.
स्वऽवान् १. ३५, १०; ११८, १; ३. ५४, १२; ६. ४७, १२; १३; ६८, ५; १०. ९२, ९.
स्वऽविंद्युतः ५. ८७, ३.
स्ववृंक्तिऽभिः १०. २१, १.
स्वऽवृजं १०. ३८, ५.
स्वऽवृंष्टिं १. ५२, ५; १४.
स्वऽशोंचिः ६. ६६, ६.
स्वश्वऽयुः ८. ४५, ७.
स्वसंरं ६. ६८, १०; ८. ९९, १.
स्वसंरस्य ३. ६१, ४; ५. ६२, २.
स्वसंराणि १. ३, ८; ३४, ७; २. १९, २; ३४, ५; ३. ६०, ६.
स्वसंरे ९. ९४, २.
स्वसंरेषु २. २, २; ३४, ८; ८. ८८, १.
स्वसा १. १२३, ५; १२४, ८; १८०, २; १९१, ६; २. ५, ६; ३२, ६; ८. १०१, १५; १०. १०, ११.
स्वसारः १. ६२, १०; ७१, १; १६४, ३; १९१, १४; २. ५, ५; ३. २९, १३; ४. ६, ८; २२, ७; ७. ६६, १५; ८. ५९, ४; ९. १, ७; ६५, १; ७१, ५; ८२, ३; ८६, ३६; ८९, ४; ९१, १; ९३, १; ९८, ६; १०. १२०, ९.
स्वसारः ३. ३३, ९.
स्वसांरं १. ९२, ११; १०. ३, ३; १०, १२; १०८, ९; १२७, ३.
स्वसांरा १. १७८, २; १८५, ५; ३. ५४, ७.
स्वसांरौ ३. ५५, ११.
स्वसुः ४. ५२, १; ६. ५५, ४; ५; ७. ७१, १; १०. १७२, ४.
स्वऽसृत् १. ८७, ४.
स्वऽसृतः १. ६४, ११.
स्वसुऽस्वं १०. १०८, १०.
स्वसृंऽभिः ९. ७२, ३; १०. ९४, ४.
स्वसृः ६. ६१, ९; १०. ५, ५.
स्वसृंणां १. १२४, ९; ३. १, ३; ११.
स्वऽसेंतवः ८. ३९, १०.
स्वऽसेंतुः १०. ६१, १६.
स्वस्तयें १. १, ९; २२, १२; ३५, १;

८९, ५; ९७, ८; २. २, ६; ३२, ८; ३. १०, ८; ३०, १८; ४. ३१, ११; ३९, ४; ५. १७, ५; २८, २; ५०, ५; ५१, १२[३]; १३[३]; ६४, ६; ६. १५, १८; ५७, १; ६; ७. ३९, २; ८. १८, २०; ३१, ११; ९. ६४, ३०; ७५, ५; ९६, ४; १०. ३६, १२; ६३, ३–१४; ६५, १०; ६६, १; १४; १२६, ५; १७८, १; २.

स्वस्ति १. ८९, ६[४]; ११६, ६; ८; ११७, १५; १७४, ९; २. ९, ६; १५, ५; ३३, ३; ३८, ९; ३. ३१, २०; ५३, २०; ४. ११, ६; ५. ४, ११; १६, ५; ४२, ४; १५; ५१, ११[४]; १२; १३; १४[४]; १५; ६. ४, ८; २०, ६; ४७, ८; ११; ८. १६, ११; ३१, ११; ४८, ८; ९. ९७, ३६; १०. ७, १; १४, ११; ३५, ३; ५९, ६; ६३, १५[४].

स्वस्तिः ३. ३८, ९; १०. ५९, ७; ६३, १६.

स्वस्तिऽगां ६. ५१, १६; ८. ६९, १६.

स्वस्तिऽदाः १०. १७, ५; ११६, २; १५२, २.

स्वस्तिऽभिः १. १८९, २; ५. ५३, १४; ७. १, २०; २५; १०. ५६, ७.

स्वर्सित २. २९, ३; ४. ५५, ३; ६. २, ११; २२, १०; ५६, ६; १०. ९९, १२.

स्वस्तिऽमत् ६. ४६, ९; ९. ८४, १.

स्वस्तिऽमतः १. ९०, ५.

स्वस्तिऽवाहं १०. १०१, ७.

स्वस्तौ २. ३८, १.

स्वस्मिन् १. १३२, २[२].

स्वस्य १. ११९, ८; ४. १७, २; ५. १८, २; ६. १७, ९; ४४, २२.

स्वस्यंऽइव २. ४, ४.

स्वस्याः ९. ७९, ३.

स्वस्त्रा १. ६५, ४.

स्वस्त्रे १. १२४, ८.

स्वस्त्रोः १. ११३, ३.

स्वा २. २३, ६; ७. १, ६; १०. २३, ४; ८३, ५.

स्वाः १. ५२, ४; ७२, ५; ३. ३१, २१; ३५, ८; ७. ७, २; ९०, ३; १०. १४, २; ९५, ९.

स्वात् ५. ८७, ४; ६. १७, ५; १०. १२४, २.

स्वादते ९. ६८, २.

स्वादनं ५. ७, ६.

स्वादवः ८. २, २८.

स्वादिष्ट १. १८७, ५.

स्वादिष्ठः ९. ६२, ९; ९७, ४८.

स्वादिष्ठं १. १३६, १; ८. ४९, ४; ९. ७८, ४.

स्वादिष्ठया ३. ५३, २; ९. १, १.

स्वादिष्ठा १. ११०, १; ४. १०, ५; ८. ८६, ४.

स्वादीयः १. ११४, ६; ८. २४, २०; १०. १२०, ३.

स्वादु १. १६४, २०; २२; ८. ६८, ११.

स्वादुः ६. ४४, २१; ४७, १; २; ८. १७, ६; ९. ५६, ४; ८५, ६[२]; ९७, ४; १०९, १; ११०, ११; १०. १३६, ६.

स्वादुऽक्षद्मा १. ३१, १५.

स्वादुना १०. १२०, ३.

स्वादुं ८. २, ३.

स्वादुऽरातयः ८. ६८, १४.

स्वादुऽसंसदः ६. ७५, ९.

स्वादो इति १. १८७, २.

स्वादोः १. ८४, १०; ११४, ६; ८. ४८, १; १०. १२०, ३; १४६, ५.

स्वाद्म १. ६९, २; ३. ३०, १४; ३१, ११.

स्वाद्मन् १०. २९, ६.

स्वाध्यानः १. १८७, ५.

स्वाध्यानं २. २१, ६.

स्वाद्धी ८. ६८, ११.

स्वानः १. १०४, १; ५. १०, ५; २५, ८.

स्वानासः ५. २, १०; ९. १०, १.

स्वानिनः ३. २६, ५.

स्वानीत् २. ४, ६.

स्वानेभिः ८. ७, १७.

स्वापय १. २९, ३.

स्वापयामसि ७. ५५, ७; ८.

स्वापिऽभिः ८. ५३, ५.

स्वापी इति सुऽआपी ४. ४१, ७.

स्वाभिः ६. ४४, ३.

स्वां १. ३३, १३; ३. ५३, ८; ६. ११, २; ८. ११, १०; ४४, १२; १०. ५६, ६; ७; ६१, ७; १२०, ९.

स्वार्य २. ५, ७; ४. ५३, ३.

स्वार्याः १०. ५४, ३.

स्वार्या १. ७१, ५; १०. १८३, २.

स्वार्यै ५. ४, ६; १०. ८, ४.

स्वारं २. ११, ७.

स्वावृक् १०. १२, ३.

स्वासस्थे इति सुऽआसस्थे १०. १३, २.

स्वासु १०. ५०, ३; १४४, ३.

स्वाहा १. १३, १२; १४२, १२; २. ३६, १; ३. ४, ११; ३२, १५; ३५, १; ५०, १; ५. ५, ११[२]; ७. ३, ७; ५९, ६; ८. ८, ५; ३४, १०; ६३, ५; १०. २, २; १४, ३.

स्वाहाऽकृतं २. ३, ११; १०. ११०, ११.

स्वाहाऽकृतस्य १. ११०, १; ८. ३५, २४.

स्वाहाऽकृतानि १. १४२, १३.

स्वाहाऽकृतिं ९. ५, ११.

स्वाहाऽकृतीषु १. १८८, ११.

स्वित् १. १५०, १; १६१, १०; १२; १६४, ४; ६; १७[२]; १६८, ६; १८२, ७; ४. १७, १२; १८, ७; ३५, ४; ५१, ६; ६. ९, २; ६; १८, ३[२]; २१, ४; ३५, २; ८. २१, ११; ५८, १; ६४, ८[२]; ९; ७५, ७; १००, १०; १०. १२, ५; ३१, ७; ३४, १०; ४०, २; १४; ६७, १; ८१, २[२]; ८२, ५; ८६, २०; ८८, १८; ८९, १४; १११, ८; ११४, ९; १२९, ५[२]; १३५, ५; १६८, ३.

स्वे १. १, ८; ७१, ६; ९१, १३; ९४, १४; १०८, ७; १४३, ४; २. २, ४; ११; ३५, ७; ३. १, १४; १०, २; २९, ८; ४२, ८; ५१, ९; ४. २, ८; ४, ७; १६, १०; ५०, ८;

५. १, ८; ३३, ४; ४८, ३; ६४, ५; ६. १६, ४१; ४०, ५; ७. १२, १; ३६, ५; ८. २, ७; ७९, ९; ९. १११, २; १०. ८५, ४२; १०५, १०; ११८, १.

स्वेदं ५. ७, ५; ५८, ७; १०. १०६, १०.

स्वेदंस्य १. ८६, ८.

स्वेदाःऽइव १०. १३४, ५.

स्वेदांजिऽभिः १०. ६७, ६.

स्वेनं १. १३९, २^{२}; १६५, ८; ४. ५६, ६; ७. २१, ६; ३६, ६; ७४, ६; ९०, ५; ९. ९७, १२; १०. ३१, २.

स्वनंऽइव १. १४५, २.

स्वेभिः १. ६२, ८; १००, २; १३९, २^{२}; ६. ३, ८; १०. ६७, ११.

स्वेषु ८. ८४, ८; १०. ८, २.

स्वैः १. ६८, ४; १८१, ४; ३. ५३, ८; ६. ५, ४; ६७, १; ८. १८, १३; ९७, ३; १०. ७४, २.

ह

हु १. ३७, १२; १३^{२}; ३८, १; ३९, १; ३; ५७, २; ६३, १^{२}; ४^{२}–७; ६५, ४; ६६, ४; ८०, ७; ८५, ७; ८७, ३; ८८, ५; १०३, ४; ११६, ३; १२; १४; ११७, २४; १२१, २; ४; ७; १२५, ५; १३४, २; १३९, १; २; ७; ९; १४४, १; १५१, २; ७; १५२, १; २; १५७, ५; ६^{३}; १५८, १; ३; १६४, ५०; १७३, ५; १७८, १; १८०, ४; १८५, १; २. १३, ९; १७, २; २०, ६; २४, १३; ३. ७, ६; ३२, ६; ९; १०; ३९, ५; ४८, १; ४९, २; ५४, २; १७; ५८, ८; ४. २, १४; ३, ५; ५, ११–१३; ६, १०; ७, ९; १२, ६; १६, ४; १०; १७, १; ११; १९; २२, ६; २३, ३; २४, ५; २७, ३; २९, २; ३१, ५; ४१, २; ३; ४३, ६; ७; ५६, १; ५. ६, ४; २९, ९; ३१, ८^{२}; ४१, ७; ५९, ४^{२}; ६४, ४; ७४, ३; १०; ६. २, ३; ९; ६, ३; ११, ३; ५; १८, ३; २०, १३^{२}; २२, ६; ४८, २२; ५०, ५; ६२, ३; ६३, २; ६४, ५; ७. १८, १; ३३, १३^{२}; ३७, २; ६८, ४; ५; ६९, ५; ७४, ५; ८६, ३; ८८, ४; ९३, ३; ८. ३, ६; १२; ५, १९; ७, ११; २१; ९, १८; १८, १; २१, ११; ४५, ४; ४९, ७; ५९, १; ४; ६७, ५; ७५, ३; ७६, ४; ७७, १; १०१, १४^{२}; ९. ६८, ५; ८८, १; १०. ५, ६; ७; १०, ४; १२, १; १४, १३; २२, ११; २७, ३; ३१, ५; ९; १०; ३९, ५; ९; ४०, १; ५–८; ११; ६१, १४; ७०, ९; ८०, ३; ८६, २३; ८९, ८; ९०, १०; १६; १०७, ८; ११५, २; १२१, ७; १२९, २; १५५, ४.

हंसः १. ६५, ५; ४. ४०, ५; ९. ३२, ३.

हंसं १०. १२४, ९.

हंसाःऽइव १. १६३, १०; ३. ८, ९; ५३, १०.

हंसासः २. ३४, ५; ७. ४५, ४; ७. ५९, ७; ९. ९७, ८.

हंसि १. ३१, ६; २. ३३, १५; ४. ३२, ३; ५. ८३, ९; ७. २२, २; ८. १२, १; ६२, ८; १०. ११८, १.

हंसि १. ५३, ७; ७. १९, ४; ८. ९०, ५.

हंसैःऽइंव १०. ६७, ३.

हंसौऽइव ५. ७८, १; ८. ३५, ८.

हुत १. २३, ९; ९. १०१, १३.

हुत १०. ७६, ४.

हुतः ६. ६०, ६^{३}.

हुतः ८. ३१, ९.

हुतं १. १८२, ४; ७. ८३, १; ८५, २; १०४, १; ७; ८. ३५, १२; १६; १०. ८६, १८.

हुतं १. १३२, ६^{२}; १८४, २; ७. ९३, ५; ९४, १२^{२}; १०. ४०, १३.

हुतऽवृष्णीः ४. १७, ३.

हुता १. १२९, ८; ६. ६३, १०.

हुताः १. १३३, १; १०. १०८, ४; १५५, ४.

हुतासः ६. ५९, १.

हुते १०. ११३, ७.

हुते इति १. १०४, ३.

हुत्वे १. २५, २.

हुत्वा १. १००, १८; १०३, २; २. १२, ३.

हुत्वाय १०. ८४, २; १५७, ४.

हुत्वी २. १७, ६; २०, ८; ३०, १०; ३. ३४, ९.

हुथ १. ३९, ३.

हुथः ६. ७२, ३; ७. ९९, ५.

हथांत् ८. ६७, ५.

हथैः ४. ३०, २१; ८. ७०, १०; १०. ४९, ३; ७.

हन् ५. २९, २; ६. १८, ५; २०, २; १०; २७, ५; ४७, २; १०. २२, ७.

हुन् ६. २६, ५; ७. ९, ६; १०. १८२, १.

हर्नः १. ८०, ३; ८१, ३; ८. ८९, ४.

हुनति ६. २९, ६; ८. ८९, ३.

हनंत ७. ५६, २२.

हनंवः ८. ६०, १३.

हनाम १. १६१, ५.

हनाव ८. १००, १२; १०. ८३, ६; १२४, ६.

हनिष्ठः ६. ३७, ५.

हुनिष्यन् ६. १८, ११.

हनू इति ४. १८, ९; ५. ३६, २; १०. ७९, १; १५२, ३.

हंत १०. ५३, २; ११९, ९.

हुंतन २. ३४, ९; ७. ५९, ८.

हंतंवे १. १३१, ६; ३. ३७, ५; ६; ५. ३४, २; ८. १२, २२; ९३, ७; ९. ६१, २२; १०. ११२, १; ११६, १.

हंतुवै ५. २, १०; ३१, ४; ८. ९६, ५; १०. १२५, ६; १८२, ३.

हंतां ४. १७, ८; २१, १०; ६. ४४, १५; ७. २०, २; ८. २, ३२; ३६.

हुंता १. १२९, ११; २. १२, १०; २३, १७; ८. ९८, ६; ९. ८८, ४^{२}; ९७, ४३.

हुंतारै १०. ८७, २२; १६६, १.

हंति १. ४०, ८; २. १९, ४; ३. ३१, ८; ४. २५, ७; ५. ३४, ५;

३७, ४; ८३, २; **६.** ६८, ३; ७३, ३; **७.** १०४, १२; १३[२]; **८.** ४९, २; ८४, ९; **९.** ५५, ४; ९७, १०; **१०.** ४२, ५; ८७, ११; १११, ५; १६२, ३.

हुंति **१.** १५२, २; १९१, २[३]; **२.** २५, ४; ३०, ८; **४.** १७, १९; २३, ८; ४१, २; **५.** ८३, २[२]; **६.** १३, ३; **७.** ५८, ४; ८५, ३; **१०.** ९९, ८; १३२, ५; १४६, ५; १६०, ४.

हुंतु **३.** ३३, १३; **७.** १०४, १६; **१०.** ८७, ५.

हंतो इति **८.** ८०, ५.

हंतोः **३.** ३०, १०.

हंत्वासः **३.** ३०, १५.

हुन्निति हन् **५.** २९, ४; ३२, १; **१०.** ९९, ६.

हुन्मः **७.** ५५, ६.

हन्मना **१.** ३३, ११; **७.** ५९, ८; ९४, १२; **१०.** ४८, ६; ११३, ८.

हुन्मि **१०.** ४८, ७.

हुन्यते **१०.** १५२, १.

हुन्यते **३.** ५९, २; **५.** ५४, ७.

हुन्यंते **१०.** ८५, १३.

हुन्यामं **८.** २१, १२.

हन्वाऽइव **१.** १६८, ५.

हन्वोः **१.** ५२, ६.

हर्यः **५.** ४६, १.

हर्यता **१.** ११६, १८.

हर्याः **९.** १०७, २५.

हुये **२.** २९, ४; **५.** ५७, ८; **१०.** ९५, १.

हर्येभिः **७.** ७४, ४.

हुर **१.** १६२, १२; **८.** ३३, १९.

हरः **१०.** ८७, २५; १५८, २.

हरयः **१.** १६, १; १०१, १०; १६४, ४७; **३.** ४३, ६; ५०, २; ५३, ४; **४.** १६, १; ४६, ३; **६.** ३७, १; २; ४०, ३; ४४, १९; ४७, १८; **७.** २४, ३; २८, १; **८.** १, २४; ६, ४२; ३३, १४; ४३, ४; ४६, ७; ४९, ८; ६५, ४; ६९, ५; **९.** ७८, २; ७९, १; ९६, २; १०६, १; **१०.** ९६, ६; ७[२]; ११२, २.

हुरयंत **४.** ३७, २.

हरयाणे **८.** २५, २२.

हरये **१०.** ९६, ११.

हरसः **८.** ४८, २.

हरसा **१०.** १६, ७; ८७, ५; १०; १४; १६; २५.

हरसे **९.** १०, ६.

हरस्वती **२.** २३, ६.

हुरामि **१०.** १६, १०; १६१, २.

हुरिऽअश्व **३.** ३२, ५; ३६, ९; ४४, २; **४.** ३५, ७; **७.** १९, ४; २१, १; २२, १; २; २४, ४; ३२, १५; ३७, ५; **८.** ४८, १०; ९०, ३; **१०.** १०४, ३; ५; १२८, ८.

हरिऽअश्वः **३.** ४४, ४; **८.** ६६, ४.

हरिऽअश्वं **३.** ३६, ४; **८.** २१, १०; ५३, २.

हरिऽअश्वस्य **३.** ३१, ३.

हरिऽअश्वाय **३.** ५२, ७; **७.** २५, ५; ३१, १; १२.

हरिऽअश्वेन **२.** १७, ३.

हरिः **१.** ९५, १; **३.** ४४, ३; **७.** १०, १; **९.** २, ६; ३, ३; ९; ५, ४; ९; ७, ६; ८, ६; १९, ३; २७, ६; ३३, ४; ३४, ४; ३७, २; ३८, ६; ४२, १; ५७, २; ६५, १२; २५; ६७, ४; ६८, २; ६९, ३; ५; ७०, ८; ७१, १; ७२, ५; ७६, १; ८०, ३; ८२, १; ८६, ६; ११; ३१; ३३; ४२; ४४; ४५; ९२, १; ९३, १; ९५, १; २; ९६, २४; ९७, ६; ९; १८; १०१, १५; १६; १०३, २; ४; १०६, १३; १०७, १०; १११, १; **१०.** ७९, ६; ९६, ३[२].

हुरिऽकेश **१०.** ३७, ९; ९६, ५.

हरिऽकेशः **१०.** ९६, ८; १३९, १.

हरिऽकेशं **३.** २, १३.

हरिऽचंद्रः **९.** ६६, २६.

हुरिऽजात **१०.** ९६, ५.

हुरिणस्य **१.** १६३, १.

हरिणी इति **९.** ७०, ७; **१०.** ९६, ९[२].

हरिणीषु **१०.** ९२, १.

हुरिणोऽइव **५.** ७८, २.

हरिण्या **९.** १११, १.

हरितः **३.** ४४, ४; **७.** १०३, ६; १०; **१०.** ८६, ३; ९६, ३; ४.

हुरितः **१.** १४, १२; ५०, ८; ५७, ३; ११५, ३–५; १२१, १३; १३०, २; **४.** ६, ९; १३, ३; **५.** २९, ५; ४५, १०; **७.** ५, ५; ४२, २; ६०, ३; ६६, १५; **८.** १०१, १४; **९.** ३८, ३; ६३, ९; ६९, ९; ८६, ३७; **१०.** ३१, ८; ३३, ५; ९२, ८.

हरितं **३.** ४४, १; ४; **९.** ५, १०.

हरिता **१०.** २३, ४; ९६, ३.

हुरिता **६.** ४७, १९; **९.** १०७, ८.

हरितेन **७.** १०३, ४.

हरितेभिः **१०.** ९४, २.

हुरितोः **३.** ४४, ३.

हरित्वता **१०.** ११२, ३.

हुरिद्रवः **१०.** ९४, १२.

हरिऽधायसं **३.** ४४, ३.

हुरिऽपाः **१०.** ९६, ८.

हरिऽप्रिय **३.** ४१, ८.

हरिऽभिः **१.** १६, ४; ५२, ८; १०१, १०; **२.** १८, ५; ६; **३.** ४३, ३; ४४, १[२]; ५[२]; ४५, १; **४.** २०, २; २९, १; **७.** २९, २; **८.** ३४, १; ५०, ७; ९३, ३१; **१०.** ९६, १; २; ७; ११२, ४.

हरिऽभ्यां **१.** ३५, ३; ५४, ३; ६३, ९; ७६, ३; १७७, ३; **२.** ११, १७; १८, ४; **३.** ३०, २; ६; ३५, ७; ४१, १; ४२, १; ४३, २; **४.** १५, ७; **५.** ३०, १; ३६, ५; ४०, ४; **६.** २३, १; ४; **७.** २३, ३; ३२, ४; **८.** ६, ३६; **१०.** १०४, १; ६; ११६, ४.

हरिं **१.** १२१, ८; **३.** ४४, ४; **९.** २६, ५; ३०, ५; ३२, २; ३८, २; ३९, ६; ५०, ३; ५३, ४; ६२, १८; ६३, १७; ६५, ८; ७२, १; ८६, २५; २७; ८९, ३; ९६, २; ९८, ७; ९९, २; १००, ७; १०९, १२; २१; **१०.** ९६, २; १०१, १०.

हरिंमन्युऽसायकः **१०.** ९६, ३.
हरिमाणं **१.** ५०, ११; १२.
हरिंऽभरः **१०.** ९६, ४.
हरिऽयूपीयायां **६.** २७, ५.
हरिंऽयोगं **१.** ५६, १.
हरिऽयोजनाय **१.** ६२, १३.
हरिऽवः **१.** ३, ६; ३३, ५; १६५, ३; १६७, १; १७३, १३; १७४, ६; १७५, १; **३.** ३०, २; ४७, ४; ५१, ६; **४.** १६, २१; १९, ९; २२, ७; **५.** ३१, २; ३६, २; ४; ४२, ४; **६.** १९, ६; २२, ३; ४१, ३; ४४, १०; **७.** १९, ७; २५, ४; २९, १; ३७, ४; **८.** २, १३; २१, ६; २४, ३; ५; ४०, ९; ५३, ८; ६१, ३; ९९, २; **१०.** ४९, ११; ६१, २२; ९६, १३; १०४, २; ६.
हरिंऽवते **३.** ५२, ७.
हरिंऽवंतं **१०.** ९६, २; ७.
हरिंऽवर्पसं **३.** ४४, ३; **१०.** ९६, १.
हरिंऽवान् **१.** ८१, ४; **७.** २०, ४; ३२, १२; **१०.** ९६, १०.
हरिंऽव्रतं **३.** ३, ५.
हरिंऽशिप्रः **१०.** ९६, ४.
हरिंऽशिप्रं **१०.** ९६, १२.
हरिंऽश्मशारुः **१०.** ९६, ८.
हरिऽश्रियं **८.** १५, ४; ५०, १०.
हरिऽसाचः **१०.** ९४, १२.
हरिऽस्थाः **१.** १११, १०–१३; **६.** १७, २.
हरिऽस्थां **३.** ४९, २.
हरी इति **१.** ५, ४; ६, २; १०, ३; १६, २; २०, २; ५५, ७; ६३, २; ८१, ३; ८२, १–६[२]; ८४, २; ३; ६; १११, १; १२१, ८; १६१, ६; १६२, २१; १६५, ४; १७४, ४; १७७, १; ४; १८१, ५; **२.** ११, ६; ७; १६, ६; १८, ३; ७; **३.** ३२, १; ३५, १; २; ४; ५; ४३, ४; ६०, २; **४.** १५, ८; ३२, १५; ३३, १०; ३५, ५; **५.** २७, २; ४३, ५; ५६, ६; **६.** २०, ९; ४०, १; ५७, ३; **७.** १९, ६; ३६, ४; **८.** १, २५; २, २७; ३, १७; ४, ११; १४; ६, ४५; १२, १५; २५; २८; १३, १०; २३; २७; ३१; १४, १२; १७, २; ३२, २९; ३३, ११; ३४, ९; ४५, ३९; ६८, १५; ७०, ७; ९८, ९; **१०.** २३, २; ३; ४४, २; ४९, २; ९३, ८; ९४, ९; ९६, १; २; ६–९; १०५, २; ११४, ९; १६०, १.
हरीं इवेति हरींऽइव **१.** २८, ७.
हरींणां **४.** ४८, ५; **५.** ३३, २; **८.** २४, १४; २५, २३; **१०.** २३, १.
हरीणां **८.** २४, १७; ३३, १२; ४६, १; **९.** १०५, ५.
हरें **९.** ६४, १४.
हरे **९.** २५, १; ११३, ५.
हरेंः **९.** ६६, २५.
हर्मि **१.** ६१, १.
हर्म्यें **७.** ५५, ६.
हर्म्यस्य **१.** १२१, १; **९.** ७१, ४; ७८, ३.
हर्म्या **१.** १६६, ४.
हर्म्ये **५.** ३२, ५; **८.** ५, २३; **१०.** ११४, १०.
हर्म्येभ्यः **७.** ७६, २.
हर्म्येषु **१०.** ४६, ३; ७३, १०.
हर्म्येऽस्थाः **७.** ५६, १६.
हर्य **१.** ५७, ४; १४४, ७; **३.** ४०, २; **८.** ४४, २; **१०.** ७०, १; ११२, ७; १२२, २.
हर्यत **५.** ५४, १५; **८.** ४४, ५.
हर्यतः **१.** ५५, ४; ५७, २; **३.** ५, ३; ४४, १; **९.** २५, ४; ४३, १; ३; ६५, २५; ८६, २६; ४२; ९८, ८; १०६, १३; १०७, १३; १६; **१०.** ११, ६; २६, ७; ९६, ४; १०.
हर्यतं **१.** ९३, ७.
हर्यतं **१.** ९३, १.
हर्यतं **२.** २१, १; **९.** २६, ५; ९६, १७; ९८, ७; **१०.** ९४, ८; ९६, १; ५; ११.
हर्यतस्य **८.** ७२, १८; १००, ५; **१०.** ९६, ९; १०; १२३, २.
हर्यता **८.** १२, २५; २७; **१०.** ९६, ६.
हर्यताभ्यां **८.** ६, ३६.
हर्यताय **१.** १३०, २; **९.** ९९, १.
हर्यति **४.** ५८, ८.
हर्यंते **१०.** ९६, ६; १०५, १.
हर्यते **५.** ५७, १.
हर्यथ **१.** १६१, ८.
हर्यन् **४.** २४, ७; **१०.** ४, ३; ९६, १२.
हर्यन् **३.** ४४, २[२].
हर्यंतं **३.** ४४, ५; **१०.** ९६, १२.
हर्यंति **१.** १६५, ४.
हर्यंमाणः **३.** ६, ४; **१०.** ९६, ११.
हर्यंश्वऽप्रसूताः **३.** ३०, १२.
हर्यसि **१०.** ९६, ५; ११.
हर्याः **५.** २, ११.
हर्यामसि **१०.** ११६, ८.
हर्योः **१.** ७, २; **३.** ४५, २; **४.** १६, ११; **८.** ३३, ४.
हर्षंतः **१.** १२७, ६.
हर्षंते **९.** ९६, १; **१०.** ३०, ५.
हर्षते **१.** ५१, ७; **९.** ७०, ५.
हर्षंमाणः **४.** ३८, ३.
हर्षंमाणासः **१०.** ८४, १.
हर्षय **८.** १५; १३; **१०.** १६, १४; १०३, १०.
हर्षयन् **९.** १११, ३.
हर्षयंत **४.** ३७, २.
हर्षसे **४.** २१, ९.
हर्षस्व **८.** १९, २९; **१०.** ११२, १.
हर्ष्या **१.** ५६, ५; **८.** ६८, १४.
हर्षुऽमंतः **८.** १६, ४.
हवः **७.** १३, ३१–३३; **१०.** ७४, २.
हवते **१.** १८३, ५; **२.** ३३, ५; **६.** ३७, १; **८.** ८५, ३.
हवते **१.** १०५, १७; **३.** २०, १; **५.** ४२, १५; **६.** २६, २; **७.** २२, ६; ५६, १८; ७३, १; **८.** ८६, १; **९.** ८०, १; **१०.** १५०, ५.
हवनं **८.** ५२, ७; ५४, ४.
हवनऽश्रुत् **२.** ३३, १५.
हवनऽश्रुतः **६.** ५२, १०; **१०.** ६४, ६.
हवनऽश्रुतः **८.** ६७, ५.
हवनऽश्रुतं **१.** १०, १०; **८.** १२, २३.

हुवनऽश्रुतां ५. ७५, ५.

हुवनऽश्रुता ६. ५९, १०; ७. ८३, ३; ८. ८, ७.

हुवनऽस्यदं १. ५२, १.

हर्वना ६. ६९, ४.

हर्वनानि ५. ५६, २; ६. ३४, ४; ३५, ३; ७. ६८, २; १०. ८१, ७.

हर्वनाय ६. ६३, २.

हर्वऽनेषु १. १०२, १०; १०. ६१, ३.

हुवंत १. १२, २; १०. ११८, ५.

हर्वंते १. ४५, ५; ६; ११७, १०; ६३, ६; २. १२, ९; ३. ४३, २; ५. ३५, ६; ६. २५, ६; ३३, २; ७. २६, २; ३०, २; ६९, ६; ८२, ९; ८. १, ३; ६, ३७; १५, १२; ३४, ४; ६६, १२; ६८, ५; १०. १७, ९; २५, ९.

हुवंते १. २३, ३; ४७, ४; ६३, ६; १४२, १३; ३. ३२, १४; ४३, १; ५८, ४; ४. २५, ८; ४२, ५; ६. २१, १; ७. २७, १; ७४, १; ८३, ६; ८. ५, १७; १६, ५; ४६, १२; १०. १७, ७; ४८, १.

हर्वं १. २, १; १०, ९; १७, २; २३, ८; २५, १९; ३०, ८; ४५, ३; ४७, २; ४८, १०; ८६, २; ९३, १; ११४, ११; १२१, ३; १२२, ११; १४२, १३; १७८, ३; १८१, ७; १८३, ५; २. १०, २; ११, १; २४, १५; ४१, ४; १३; १५; ३. ६२, २; ४. ९, ७; ५. १४, ५; २४, ३; ४३, ११; ४६, ६; ७४, १०; ७५, १; ७८, ५; ८७, ८; ९; ६. २१, १०; २३, ४; २४, २; ४५, ११; ५०, ५; ६; १०; ५२, १३; ६०, १५; ६२, ७; ६९, ७; ७. २२, ४; २८, २; ६७, १०; ८२, ८; ९४, १; ८. १, २७; ३, १४; १८; ६, १८; ७, ९; १३, ७, २२, १२; २६, १०; ३३, ९; ३५, १३; ३८, ८; ४३, २२; ४५, १८; ५०, ५; ५२, ८; ५४, ३; ४; ६१, १०; ६६, १२; ७३, ५; १०; ७४, ११; ८२, ६; ८५, १; २; ४; ९५, ४; १०. २६, ९; ३०, ८; ३७, ६; ३९, ७; ६३, २; ६४, ६; ६६, १०; ७०, १०; १०६, ४; १४८, ५; १७१, १.

हर्वमानं ४. २९, ४; ८. ७, ३०; ५०, ४.

हर्वमानाः १. १०२, ५.

हर्वमानाग ३. १, २३.

हर्वमानासः ५. ३२, ११; ८. ५०, ४.

हुवसा १. ६४, १२; ६. ६६, ११.

हर्वस्य २. ३६, ६; ८. ३५, ४.

हर्वा १. १२२, ६; ७. २९, ३; ६२, ५; १०. २७, ८.

हर्वानां ८. २६, १६.

हर्वामहे १. ७, १०; १६, ४; ११८, १०; १३०, १; १७७, २; ४. ३९, ४; ६. १९, १२; ४६, १; ७. ८३, ९; ८. ७, ११; २२, ११; २६, ९; १०१, ८; १०. १६०, ५; १६७, २.

हुवामहे १. ७, ५; १६, ३; २१, ३; ४; २२, २; ७; २३, २; ४; ७; १०; ३०, ७; ३६, १८; ७८, ३; ८१, १; १०१, १–७; १०२, ९; १०६, १; ११४, ८; १२०, ३; १२७, ८; १४४, ५; २. १६, १; २३, १; ८. ३४, ११; ३. २६, १; २; ४०, १; ४२, ४; ९; ४. ३२, १३; ३७, ५; ४९, ५; ५. १३, १; २०, ३; ६४, १; ८६, २; ४; ६. ५९, ३; ६०, ५; १४; ७. ३२, २३; ४१, १; ८२, ४; ९४, ६; ९६, ४; ८. ३, ५; ७, ६; ११, ६; ८; ९; १७, ३; २१, १; २६, ३; २७, ७; ३२, १०; ४३, १३; २३; २८; ४५, १७; ५१, ६; ५२, ६; ५३, २; ६१, १०; १४; ६४, ६; ६५, ६; ७६, ५; ६; ८६, ४; ९२, २०; ९३, ३०; ९९, ८; ९. ६५, ४; १०. ३९, १; ४१, १; ६३, ९; ६४, ८; ६५, ९; ६६, ४; १४१, ३; ४; १५०, २[२]; १५१, ५; १८४, ३.

हर्वासः ६. २३, ८.

हुविः १. १२, १०; १३, ११; २३, १८; २६, ६; ३४, ८; १०; ३६, ६; ४५, ८; ९४, ३; १०१, ८; ९; ११४, ३; २. १, १३; १४; ३, १०; १६, १; २४, १२; २६, २; २३, ७; ३७, ६; ३. ४, १०; ६, १; २६, ७; २८, १; ५०, १; ५९, ५; ४. ४९, १; ५. ५, ११; ६, ५; २८, २; ४४, ३; ६. ७५, ८; ७. १३, १; १५, १; ५९, ९; १०२, ३; ८. १९, २७; २७, २२; ६०, १४; ७२, १; ९. ७, २; ३४, ५; ६७, २८; ७४, ६; ८३, ५; १०७, १; ११४, ४; १०. १४, १३; १४; २०, ६; ८६, १२; १३; ८८, १; ७; ८; ९०, ६; ९१, १५; १०७, ४; ११०, ११; ११६, ७; १२४, ६; १५१, १; १६५, २; १७९, २; १८१, २.

हुविःऽअर्दः १०. १५, १०.

हुविःऽअर्थ १. १६३, ९; १०. ९४, २.

हुविःऽअद्याय ५. १, ११; ४, ४; ७. ११, ५.

हुविःऽकृतः ८. ६०, १५; १०२, १३; १०. ६६, ६.

हुविःऽकृतं १. १३, ३; १६६, २.

हुविःऽकृति १०. ९१, ११.

हुविःऽकृतिं १. १८, ८; ९३, ३.

हुविःऽदे १. १५३, ३; ४. ३, ७; ७. ६८, ६.

हुविःऽपतिः १. १२, ८.

हुविःऽपाः १०. १५, १०.

हुविःऽभिः १. २४, ११; १४; ७६, ५; ९५, ६; २. ३३, ५; ३५, १२; ३. १, १५; १४, ३; ४. ५०, ६; ७. १४, १; ४०, ५; ९७, ३.

हुविःऽमथीनां ७. १०४, २१.

हुविःऽवाट् १. ७२, ७.

हुविःऽहविः ९. ७७, ३.

हुविषः १. ९३, ७; १३१, ६; १६२, १७; ३. ३५, १०; ५. ६०, ६; ७. ११, ४; ६८, २; १०. ५१, ७–९; ९१, १; १८१, १.

हुविषां १. ४६, ४; ५८, १; ८४, १८;

९१, १९; ९३, ८; १६६, ३; २. २, १; ९, ४; १०, ४; १६, ४; २६, ३; ३. १७, २; २९, ८; ४. ४, ७; ५. ३, ६; २८, १; ३७, २; ६. ४७, २७; ५४, ४; ६९, ६; ७. २, ४; १४, २; १७, ३; ८. ४८, १२; १३; ९६, ८; १०. १४, १; ४; २०, ८; ३०, ३; ४०, ४; ६५, ६; ८१, ६; ९०, ६; ९५, १८; ९८, ४; १२१, १; १२४, ६; १५९, ४; १६१, १; ३; ४; १६८, ४; १७३, ३; ६; १७४, १; १९१, ३.

हविर्षि ६. ५२, १७; १०. ८१, ५; ९१, ८.

हविर्षे १०. १६, १२.

हविष्मः ९. ८३, ५.

हविष्मंतः १. ५७, २; १७३, १२.

हविष्मंता १. १२८, २[२]; १५६, १; ७. ६७, १; १०. ३९, १.

हविष्मंती ७. १, ६; ८. २३, २२; ६०, १.

हविष्मंतीः ८. ६, २७; १३, १६.

हविष्मंतीं ३. १९, २.

हविष्मंते १. १३, १; ३. १०, ४; ५. २, १२; १०. ४३, ८; १२५, २.

हविष्मंत्ऽभिः ३. २९, २.

हविष्मंतः १. १४, ५; ३६, २; ६०, २; ११४, ८; ३. १३, २२; ६, १; २७, १; १४; ४१, ७; ५. ९, १; ७. ११, २; ८. ५, १७; ७४, २; १०. ३०, २; ७०, ३; ७७, १; ९१, ९; १२२, ४.

हविष्मंतं ४. ४५, ७; ८. ९, ६.

हविष्मान् १. १२, ९; १२७, १०; १५७, ६; १६२, २२; १६७, ६; १८०, ३; १८१, ९; १८३, ३; ५; ४. २, ८; ४१, १; ६. १०, ६; १६, ४६; ७३, १; ७. १, १६; ७०, ६; ८५, ४; ९. ९६, १२; १०. ४२, ४.

हविर्द्यै १. १६२, ४.

हविष्पुं ९. ७, २.

हवींषि १. ९४, ४; १७०, ५; २. ९, ३; ३७, ५; ३. ३५, ७; ७. ५७, ६; १०. २, २; ६, ३; १५, ८; ११; १२; ७०, ८; १०; ११०, १०; ११६, ८.

हवींतवे ८. १०१, ४.

हवींमन् ६. ६३, ४; ७. ५६, १५.

हवींमनि ७. ८३, ४; १०. ६४, ४; ९२, १२.

हवींमऽभिः १. १२, २; १३१, ६[२]; १५९, २; २. ३३, ५.

हवें १. ११८, ११; ६. ५२, १६; ८. १३, १३[२]; ९. ८८, ३; १०. १२८, ८.

हवेते इति २. १२, ८.

हवेंभिः ७. १९, ९.

हवेंपु ७. २, ७; ३५, १२; ३८, ७; १०. ४, १; १५, १; १०३, ११; १८२, २.

हवेंऽहवे ६. ४७, ११.

हव्यऽअत् ७. ३४, १४.

हव्यैः १. ३३, २; १००, १; १०१, ६; ११६, ६; १२९, ६; १४४, ३; २. २३, १३; ३७, २; ३. ५, ३; ४९, ३; ४. २४, २; ५. १७, ४; ३३, ५; ६. १८, ६; २२, १; ४५, ११; ७. २२, ७; ३२, २४; ३८, १; ८. १, २८; १६, ८; २०, २०; ७०, ८[२]; ७१, १५; ९०, १; ९६, २१[२]; १०. ६, ७; ३८, ४; ३९, १; ८९, १०.

हव्यऽजुष्टिं १. १५२, ७; ७. ६५, ४.

हव्यऽदातये ५. २६, ४; ५१, १; ५; ६. १६, १०; ४८, २; ८. ३५, ९; १०१, १.

हव्यदातिऽभिः ४. ८, ५; ८. १९, १३; २३, १५; २१.

हव्यऽदातिं ३. २, ८; ५. ५५, १०; ६. १, ९; ४७, २८; ७. १६, ९; १०. ७, ७.

हव्यं ६. २१, १; ७. ३०, २; ८. ९६, २०; १०. ३९, १०.

हव्यं १. १३६, १; २. ३, २; १०; ११; ३२, ६; ३. १८, ३; ५९, १; ४. ९, ६; २६, ४; ५. ४, ८; १६, २; २९, ३; ८६, ६; ६. २, १०; १५, १०; ७. १, २३; ४, १; ३९, ६; ४७, ३; ६४, १; ६७, ७; ८६, २; ९९, ७; ८. १९, १; १०. ८, ५; १२, २; १४, १५; १६, ९; ५२, १; ८०, ४; ११०, १०.

हव्यऽवाट् ५. ६, ५.

हव्यऽवाट् १. १२, ६; ६७, १; ३. २, २; ११, २; २७, ५; ५. ४, २; २८, ५; ८. ५६, ४; १०. १२४, १.

हव्यऽवाहः ३. ४३, १.

हव्यऽवाहन १. ३६, १०; ४४, ५; ३. ९, ६; १०. ११८, ५; १५०, १.

हव्यऽवाहनः १. ४४, २; ५. ११, ४; २५, ४; ६. १६, २३; ७. १५, ६; ८. २३, ६; १०. ११९, १३.

हव्यऽवाहनं २. ४१, १९; ५. ८, ६; २८, ६; ८. १९, २१.

हव्यऽवाहनीः १०. १८८, ३.

हव्यऽवाहं १. १२, २; ४४, ८; १२८, ८; ३. ५, १०; १०, ९; १७, ४; २९, ७; ४. ८, १; ६. १५, ४; ८; ७. १०, ३; ११, ४; १७, ६; ८. ४४, ३; १०२, १७; १८; १०. ८, ६; ४६, ४; १०; ५२, ३; ११८, ९.

हव्यऽसूदः १. ९३, १२; ४. ५०, ५.

हव्या २. ३९, १; ६. ६१, १२.

हव्या १. ७४, ६; ७५, १; ९१, ४; ९३, ११; १०५, १४; १२७, ८; १२८, ७; १३९, ३; १४२, ११; १७१, ४; १८७, ११; १८८, १; २. २, ६; ३. २१, १; ४; ५४, २२; ४. ९, ५; ५. ७, ३; ९, १; १४, १; १८, १; ६. १२, २; १५, १४; ४७, २८; ५२, ११; ७. १, १८; २, २; ९, १; ५६, १२; ५९, ४; ८. १९, ११; २०, ९; १०; १६; २३, ६; २७, ६; ४४, १;

५; ६०, १५; **१०.** १५, ४; २०, ५; ७६, ७; १२८, ४; १७६, २.
हव्याः **६.** २१, १.
हव्यानि **१.** ७४, ४; १०१, १०; १२७, ६; १३५, ३; ४; १४२, १३; १८८, १०; **३.** ५२, २; ५३, १; ६२, ४; **४.** १५, ३; **५.** ५, १०; **६.** ६०, १५; **७.** ६८, १; **८.** ९, १४; १९, २४; २३, २६; ३८, ५; ४४, ८; ७४, ३; १०१, ७; १०; **१०.** १५, १२; १६, ११; ५१, ५.
हव्यार्य **१.** ४५, ६; **३.** २९, ४; **५.** १४, ३.
हव्यासु **१०.** १४७, २.
हव्येन **४.** ४२, १०; **६.** ५२, ८.
हव्येभिः **१.** १५३, १; **४.** ४२, ९; **७.** ८, १; ८४, १; **८.** २६, ३; ७४, ६; **१०.** २४, २.
हव्यैः **२.** २, ५; २६, ४; **३.** ३१, ११; **४.** २, १; **५.** ३, ८; ४, ७; **६.** १, १०; **७.** ३, ७; ६३, ५; ६८, ४.
हसनां **९.** ११२, ४.
हसाय **१०.** १८, ३.
हस्कर्तारः **४.** ७, ४.
हस्कारात् **१.** २३, १२.
हस्कृतिः **८.** ८९, ६.
हस्तः **२.** ३३, ७; **१०.** ६०, १२.
हस्तऽगृह्य **१०.** ८५, २६; १०९, २.
हस्तऽग्राभस्य **१०.** १८, ८.
हस्तऽघ्नः **६.** ७५, १४.
हस्तऽच्युती **७.** १, १.
हस्तऽच्युतेभिः **९.** ११, ५.
हस्तं **६.** ५४, १०; **८.** २४, ५; **१०.** ४७, १; ८५, ३६.
हस्तऽयतः **५.** ४५, ७; **१०.** ७६, २.
हस्तयोः **१.** २४, ४; ३८, १; ५५, ८; ८७, ४; १३५, ९; १६२, ९; १७६, ३; **६.** ३१, १; ४५, ८; **९.** १८, ४; ९०, १.
हस्तऽवन्तं **१०.** ३४, ९.
हस्ता **४.** २१, ९; **८.** ६८, ३.
हस्ताऽइव **२.** ३९, ७.
हस्तात् **३.** ३५, १०; **१०.** १८, ९.
हस्ताभ्यां **१०.** १३७, ७.
हस्ताय **८.** ७०, २.
हस्तासः **४.** ५८, ३.
हस्तिनः **१.** ६४, ७; **३.** ३६, ७; **९.** ८०, ५.
हस्तिऽभिः **५.** ६४, ७.
हस्ती **४.** १६, १४.
हस्ते **१.** ६७, २; ७२, १; ११४, ५; १२८, ६; **२.** १६, २; **३.** ३९, ६; **६.** १६, ४०; १८, ९; २२, ९; २९, २; **७.** २८, २; ४५, १; **८.** २९, ३; ७०, १२; ७८, १०; **९.** ८९, ६; **१०.** ९७, ११.
हस्तेन **१०.** १०९, ३.
हस्तेभिः **४.** २, १४.
हस्तेषु **१.** ३७, ३; १६८, ३.
हस्तैः **९.** ७९, ४.
हस्तौ **१०.** ११७, ९.
हस्तौऽइव **२.** ३९, ५.
हस्त्यं **२.** १४, ९.
हस्राऽइव **१.** १२४, ७.
हाः **३.** ५३, २०.
हारिद्रवाऽइव **८.** ३५, ७.
हारिद्रवेषु **१.** ५०, १२.
हारिऽयोजन **१.** ६१, १६.
हारिऽयोजनं **१.** ८२, ४.
हार्दि **२.** २९, ६; **५.** ४४, ९; **८.** ७९, ८; **९.** ८, ३; ६०, ३; ७०, ९; ८४, ४; ८६, १९; १०८, १६.
हासते **९.** २७, ५; **१०.** १२७, ३.
हासमाना **१.** १६९, २.
हासमाने इति **३.** ३३, १.
हासयन्ति **३.** ५३, २३.
हासुः **८.** ७५, ८.
हास्महि **१०.** १२८, ५.
हि **१.** २, ४; ६, ७; ८, ८; ९; १०, ३; १०; १४, १२; १५, २; ३; ५; १६, ४; १७, २; ४; २३, १०; २४, ४; ८; १३; २५, १; ४; २६, १; ३; ६; ८; २८, ५; ७; २९, १; ३०, ३; १८; २१; ३२, ६; ३३, ४; ३४, १; १०; ३६, १२; ३७, ९; १५; ३९, ९; ४०, २; ४४, २; ७; ९; ४५, २; ४७, १०; ४८, १०; ११; १४; ४९, ४; ५२, ३; ७; ५३, १; ५४, ३; ५५, ६; ७०, ३; ७३, ६; ७७, ३; ८०, १; ३; ८१, २; ७–९; ८२, २; ८४, ९; ८५, १; ८६, १; ६; ८७, ४; ९०, २; ९२, १५; ९३, ७; ९४, १; ३; ९७, ६; ९८, १; १०२, ५; १०५, १८; १०८, ३; ६–१२; १०९, १–३; ११४, ९; ११६, १५; ११८, ११; १२०, ६; ७; १२७, ३; ६; ९; १२८, ५; १२९, ३; ११; १३१, १; २; ६; १३३, ६^{2}; ७^{2}; १३५, १; ४; १३८, २; १४०, ८; १४१, ९; १४२, ४; १४४, ६; १४५, ५; १५४, ५; १६०, १; १६३, १३; १६४, ८; २९; ४०; १६५, ५–७; १०; १६९, १; ३; १७०, ३; १७१, २; १७३, ८; ११; १२; १७५, ३; १७९, २; ५; १८०, ७^{3}; ८; १८२, २; १८६, १०; १८८, ६; ७; ९; १८९, ६; १९०, २; **२.** १, १६; २, १३; ५, ४; ६, ७; ९, ४; ११, १; १४, १; ३; १६, ४; १८, ३; ६; ७; २३, १७; २४, ७; २७, ६; २८, ८; ३०, ३^{2}; ६; ३५, १; ५; ९; ३६, ३; ३७, ५; ३८, १; २; ४१, १०; **३.** १, ११; १३; २, ६; ३, १; ६, ९; ७, ७; ११, ३; १३, ३; १४, ५; ६; १८, १; १९, ४; २६, ८; २८, ५; ३०, १; ४; ३१, १२; ३२, १२; ३६, ९; ३९, ३; ८; ४१, ६; ४२, ६; ४३, २; ३; ५१, ३; १०; ५२, ४; ५३, १८; ५४, ४; १६; ५५, १७; ५८, ४; **४.** १, १; ३, १०; ६, १; ७, २; ८, २; ९, ५; १०, २, ७; १२, ४; १४, ४; १७, १८; २३, ८; २४, १; २९, २; ३१, ५; ७; ३२, ७; २१; ३३, ६; ९; ३४,

१; ३५, १; ३६, ७; ३७, ४; ३८, १; ४१, ७; ४२, ९; ४३, ३; ४६, १; ४; ४७, २; ५१, ५; ५४, २; **५.** १, ५; २, २; ४, ७; ८[२]; ४, ६; ५, २; ६, ३; ७, ७; १४, ३; १६, १; २; ४; १७, २; ५; २१, २; २३, २–४; २५, २; २९, ३; ३०, ८; ९[२]; ३२, १२; ३३, ६; ३४, ८; ३५, ३; ४; ४४, १०; ४५, ४; ५०, २; ५२, २; ५८, ७; ६४, २; ६५, २; ४; ६६, २; ४; ६७, ३; ४; ७०, १; ७१, २; ७४, ४; ६; ७६, ४; ७७, १; ८२, २; ३; ८७, ६; **६.** १, १; १३; २, १; २; ६–८; ४, ४; ७; १०, १; ११, ३; १३, २; १४, २; ३; ५; १५, ६[२]; १४; १५; १६, ३; २०; २३; ४३; १८, ४; ६; १९, ५; १०; १२; २१, ५; ८; २३, ६; ८; २९, १; ६; ३३, २; ३७, १; ४४, १३; ४५, ४; २०; २४; ४६, १; ४७, १८; २६; ४८, ३; १७; १९; ४९, ११; ५०, ७; ५१, ७; १०; १४[२]; ५८, १; ५९, ७; ६३, १; ८; ६५, ४; ५; ६६, ३; ६७, ६; ६८, २[२]; ७१, ६; **७.** ३, ३; ४, ५–७; ५, ६; ७, ३; १०, ५; ११, ४; १८, १; २; १८; २१, ६; ८; २२, ६; २३, ४; ५; २५, ४; २७, २; २८, १; ३; ४; ३२, २; २४; ३३, १; ३७, ३; ३९, ४; ४०, ४; ५; ४६, २; ४८, ३; ५३, १; ३; ५६, २; ५७, २; ५९, ५; ७; ६०, ५; ६५, २; ६७, ९; ६९, ६; ७२, २; ७४, १; ८२, ८; ८३, ५; ८५, ३; ९१, ५; ९३, १; २; ६; ९४, ५; ९७, ७; ९९, ३; १००, ३; **८.** १, ३; ७; १७; २१; २, ११; २१; ३५; ३, १७; १८; ४, १७; ५, १६; २८; ६, १०; १४; ४१; ७, ३६; ८, ६; ९, ६; ११, ८; १०; १३, १; ११; ३३; १४, ११; १७, १; १८, २; ५; २२; २०, ३; १४; २२; २१, २; ४; १०; १८; २२, ९; २३, १; १८; २९; २४, २; ९; १६; २४; २५, १५; २०; २६, ५; ६; ९; २०; २४; २७, ४; १०; ११; १४; ३३, १०; १९; ३८, १; ३९, १; ३; ४०, ३; ४१, ४; ४३, १।४; ४४, १८; २४; २९; ४५, १२; १३; १९; ३२; ३५; ४६, २; ७; २५; ४७, ११; ४८, ६; ९; ५१, ५; ५३, ८; ५४, ६; ७; ६०, २; १०; ६१, २; ३; ५–७; १४; ६६, ६; १२; ६७, ३; ८; १६; १७; ७१, २; ७५, १; १६; ७८, ३; ८१, २; ८३, ४; ५; ८४, ६; ८६, १; ३; ८८, ५; ९०, ४; ९२, ५; १३; १८; २६; २८; ३३; ९३, ३३; ९५, ३; ९; ९७, ११; ९८, ५; ७; ११; १९३, १३; **९.** १९, २; २०, २; ४९, ४; ५१, ४; ६५, ४; ६९, ८; ७०, ९; ७८, २; ७९, ३[२]; ८१, २; ८५, २; ८७, ६; ८८, ४; ९४, ५; ९६, ११; ९७, २७; ९८, ४; ८; १०८, ३; ११०, २; ३; ५; **१०.** १, ७; २, ६; ५, ४; ६, ७; ८, ४; ९, १; १२, ५; १४, ४; १७, १०; १८, १२; २३, ६; ७; २६, १; २८, १; ६[२]; २९, ७; ३०, २; १२; ३२, ७; ३४, ११; ३५, ७; ३५, ५; ३८, ५; ४४, ५; ४५, ४; ४६, १०; ४७, १; ५३, १; २; ६१, २३; २६; ६३, २; १६; ६४, ७; ६५, ३; ६७, ४; ११; ६८, ७; १२; ७१, १०; ७२, ५; ७३, ५; ७५, १; ९; ७६, २; ७८, ८; ८२, १; ८३, ४; ८५, २१; ८६, १; २; १४; ८८, १०; ८९, १६; ९२, ४; १०; ९३, ३; ९५, ११; ९६, २; १०; ९९, २; १००, ५; १०१, ८; १०६, २; ९; १०८, १; १११, १–३; ६; ११२, १; ७; ११४, २; ११७, ५; १२०, ४; १२३, ४; १२६, २; १३२, ६; ७; १३४, ६; १३७, ३; १४२, १; १४३, ३; १४४, १; १६५, २.

हिंसंति **६.** ३४, ३.

हिंसानां **१०.** १४२, १.

हिंसिष्ट **१०.** १५, ६.

हिंसीत् **१०.** १२१, ९; १६५, ३.

हिंस्रः **१०.** ८७, ३.

हिंस्रं **१०.** ८७, ९.

हिंस्रा **१०.** ८७, ५.

हिङ् **१.** १६४, २८.

हिङ्ऽकृण्वती **१.** १६४, २७.

हिणुतात् **१०.** १६, १.

हिणोतन **१०.** ३०, ७.

हिणोमि **१०.** १६, ९.

हितः **१.** ५१, ७; १२८, ७; **२.** ३६, ५; **३.** २८, ३; **५.** १, ५; ४४, ३; **६.** १६, १; **७.** ६७, ७; **८.** ६०, ४; ९३, ८; १००, २; **९.** ९, १; ४; १५, ३; २५, २; २८, १; ४४, २; ६२, १०; ६६, २३; ७०, ५; १०; ८६, १३; ९८, २; **१०.** ५९, ४; ७१, १०; ११४, १०; १३६, ४; १४०, ३; १८६, ३.

हितऽप्रयसः **८.** २७, ७; ६०, १७; ६९; १८; **१०.** १२२, ७.

हितऽप्रयसा **१०.** ६१, १५.

हितं **१.** २३, १४; ३४, ८; ८०, ८; १०५, १२; १३५, ४; १८७, ६; **२.** ११, ५; २४, ६; ३७, ४; ३८, ७; **३.** १२, ८; **४.** ५, ८; ७, ६; ५८, ४; **५.** ११, ६; ५७, ६; **६.** ४५, २; १२; १५; **८.** ३२, २९; ४३, २५; ८०, ८; ९५, २; **९.** १०, ९; ३२, ५; ६८, ५; ७; ७४, ४; ११३, ७; **१०.** ७, ५; १६, ३; ३९, ९; १०१, ७.

हितऽमित्रः **१.** ७३, ३.

हितऽवान् **१.** १८०, ७.

हिता **१.** ५१, ७; **८.** ९, १४; २५, ७.

हिताः **१.** ५४, १०; **९.** २१, ४; ९७, २७.

हिताःऽइव **१.** १६६, ३.

हितानि **५.** ४२, ३.

हितासः ६. ५०, ४.
हिते १. ४०, २; ११६, १५; १३२, ५; ४. ४१, ६; ६. ४५, ११; १३; ६१, ५; ८. ३, ९; ९. ५३, २; १०. ६३, १४; १३२, ५.
हितेनऽइव ४. ५७, १.
हितेषु ५. १, ५; ८. ६, ५.
हित्वा ९. ९७, ४५.
हित्वा ५. ५३, १४; १०. १६५, ५.
हित्वाय १०. १४, ८.
हित्वी २. ३८, ६; ६. ५९, ६; ९. ६९, ९; १०. ९९, ५.
हिन ६. ४८, २.
हिनव १०. ९५, १३.
हिनु ६. ४५, ३०; ९. ३६, ३.
हिनुहि १. १४३, ४; ६. ४५, १४.
हिनोत ७. ३४, ६; १०. ३०, ११[२].
हिनोत २. १४, ४; ५. ७७, २; ७. ३४, ५; ९. ६२, १८; ९७, ४; १०. ३०, ८; १८८, १.
हिनोतं १. १८४, ४.
हिनोति १. १८, ४; १५३, २.
हिनोति ७. १०४, १३.
हिनोमि १. ६१, ४; २. ३२, ३; ६. ६९, १; ७. ५६, १२.
हिनोषि ६. १३, ३; ८. ४, १६; ७१, ५.
हिन्व १०. १५६, २.
हिन्वति ३. ३१, १६.
हिन्वतीः ९. ६६, ८.
हिन्वतु १. २७, ११.
हिन्वते ९. ७२, १.
हिन्वन् ५. ३६, २; ९. १०२, १; ८.
हिन्वन् १०. ९६, ७.
हिन्वंतः १०. ९६, २.
हिन्वंति ३. ५३, २४; ७. ६, २; ९. ८, ४; ६५, १; ८; ६७, ९; ९७, ५७; ९९, २; १०. १२०, ९.
हिन्वंति १. ८४, ११; १४४, ५; ३. ४६, ५; ८. ४३, २९; ४४, १९; ९. १, ८; २६, ५; ६; ३०, ५; ३२, २; ३८, २; ३९, ६; ५०, ३; ५३, ४; ७८, ३; १०१, ३; १०६, ११; १०७, १३; २४; १०. २७, १६; ७१, ५.
हिन्वंतु १. २३, १७; १११, ४; २. ३४, १२; १०. १५६, १.
हिन्वस्य ८. ४०, ९.
हिन्वानः २. ३६, १; ७. १०, १; ९. १२, ७; ८; ३४, १; ४८, ५; ६२, १०; ६३, ७; ६४, ९; २९; ६५, २५; ६७, ४; ७६, २; ८४, ४; ९०, १; ९७, ३२; १०५, २; १०७, १५; १०. १३९, ५.
हिन्वानं ८. १, १९.
हिन्वाना १०. ६५, २.
हिन्वानाः १. १०४, ४; २. २१, ५[२].
हिन्वानासः १. ३३, ८; ९. १०, २; ६४, १६; ६५, २६.
हिन्विरे ९. ६५, २७; १०. २८, १२.
हिन्विरे ५. ६, ६; ८. १५, ८; ४३, १९; १०१, ६; ९. ७४, ८; १०. ५०, ३.
हिन्वे ४. ७, ११; ९. ६५, ११.
हिन्वे ९. ४४, २.
हिमऽवंतः १०. १२१, ४.
हिमा १०. ३७, १०.
हिमाऽइव १०. ६८, १०.
हिमाः १. ६४, १४; २. ३३, २; ५. ५४, १५; ६. ४८, ८.
हिमेन १. ११६, ८; ११९, ६; ८. ३२, २६; ७३, ३.
हिम्याऽइव १. ३४, १.
हियानः ८. ४९, ५; ९. ३०, २; ८६, ३; ९२, १; ९८, २; १०७, २६.
हियानस्य २. ४, ४.
हियानाः ९. १३, ६.
हिरणिनः ५. ३३, ८; ६. ६३, ९.
हिरण्यऽअक्षः १. ३५, ८.
हिरण्यऽअभीशुः ८. २२, ५.
हिरण्यऽअभीशुं ८. ५, २८.
हिरण्यऽकर्ण १. १२२, १४.
हिरण्यऽकेशः १. ७९, १.
हिरण्यऽकेश्या ८. ३२, २९.
हिरण्यऽगर्भः १०. १२१, १.
हिरण्यऽचक्रान् १. ८८, ५.
हिरण्यऽजित् ९. ७८, ४.
हिरण्यऽजिह्वः ६. ७१, ३.
हिरण्यऽस्रक् ५. ७७, ३.
हिरण्यऽदंतं ५. २, ३.
हिरण्यऽदाः २. ३५, १०; १०. १०७, २.
हिरण्यऽनिर्निक् १. १६७, ३; ५. ६२, ७.
हिरण्यऽनेमयः १. १०५, १.
हिरण्यऽपक्षं १०. १२३, ६.
हिरण्यऽपर्णाः ४. ४५, ४.
हिरण्यऽपाणिः १. ३५, ९; ३. ५४, ११; ६. ५०, ८; ७१, ४.
हिरण्यपाणिऽभिः ८. ७, २७.
हिरण्यऽपाणिं १. २२, ५.
हिरण्यऽपाणे ७. ३८, २.
हिरण्यऽपावाः ९. ८६, ४३.
हिरण्यऽपिंडान् ६. ४७, २३.
हिरण्यऽपेशसा ८. ८, २; ३१, ८.
हिरण्यऽप्रउगं १. ३५, ५.
हिरण्यऽबाहुः ७. ३४, ४.
हिरण्यं १. ४६, १०; २. १५, ९; ४. १०, ६; ८. ६५, ११; १०. २३, ३; १०७, ७.
हिरण्यंऽइव १. ४३, ५.
हिरण्ययः १. ७, २; ५७, २; ४. ५८, ५; ७. ६९, १; ८. ५, २९; ३३, ४; ६१, ६; ६६, ३; ७७, ११; ९. १०७, ४.
हिरण्यये १. २५, १३; ५६, १; ८५, ९; १३९, २; ३. ३४, ९; ५. ६७, २; ६. ५६, ३; ७. ८७, ५; ८. २९, १; ४६, २४; ६८, ३; ६९, १६; ९. ५, १०; ६४, २०; ७१, ६; ८५, ११; १०. ४८, ४.
हिरण्यया ६. ७१, १; ५; ७. ४५, २; ८. १, ३२; ५, २९; ७२, १२; ७८, २.
हिरण्यऽया ७. ६६, ८.
हिरण्ययाः १. १८०, १; २. २७, ९; ५. ८७, ५.
हिरण्ययात् २. ३५, १०.
हिरण्ययान् ५. ५५, ६.
हिरण्ययासः ६. ६६, २.

हिरण्ययी ८. ५, २९; ३३, ११; १०. ७५, ८; ९३, १३.
हिरण्ययी इति १. १४४, ६; १०. १८४, ३.
हिरण्ययीः ५. ५४, ११; ६. ५८, ३; ८. ७, २५; ९. ५, ५.
हिरण्ययीं ३. ३८, ८.
हिरण्यऽयुः ७. ३१, ३; ८. ७८, ९; ९. २७, ४.
हिरण्यये १. १३९, ३²; ४; ६. २९, २; ८. १, २४; २०, ८; २५; २२, ९; ९. ७५, ३; १०. १२३, ५.
हिरण्ययेन १. ३५, २; ४. ४४, ४; ५; ८. ५, ३५.
हिरण्ययेभिः १. ६४, ११.
हिरण्यऽरथः ४. १, ८.
हिरण्यऽरथं १. ३०, १६.
हिरण्यऽरथाः ५. ५७, १.
हिरण्यऽरूपः २. ३५, १०.
हिरण्यऽरूपं ४. ३, १; ५. ६२, ८; १०. २०, ९.
हिरण्यऽवत् १. ३०, १७; ९२, १६; ७. ९४, ९; ८. २२, १७; ४९, १०; ९. ४१, ४; ६१, ३; ६३, १८; ६९, ८; ७२, ९; ८६, ३८.
हिरण्यऽवतः ८. ३२, ९.
हिरण्यऽवंतं ९. ११२, २.
हिरण्यऽवंधुरं ४. ४६, ४; ८. ५, २८.
हिरण्यऽवर्ण ५. ३८, २.
हिरण्यऽवर्णः २. ३५, १०.
हिरण्यऽवर्णं २. ३५, ११; ५. ४३, १२; १०. ८५, २०.
हिरण्यऽवर्णा ७. ७७, २.
हिरण्यऽवर्णाः २. ३५, ९.
हिरण्यऽवर्णान् २. ३४, ११.
हिरण्यऽवर्णां ३. ६१, २.
हिरण्यऽवर्तनिः ६. ६१, ७; ८. २६, १८.
हिरण्यवर्तनी इति हिरण्यऽवर्तनी १. ९२, १८; ५. ७५, २; ३; ८. ५, ११; ८, १; ८७, ५.
हिरण्यऽवाशीः ७. ९७, ७.
हिरण्यऽवाशीभिः ८. ७, ३२.
हिरण्यवाशीमत्ऽतम १. ४२, ६.
हिरण्यऽवित् ९. ८६, ३९.
हिरण्यऽवीनां ८. ६५, १०.
हिरण्यऽशम्यं १. ३५, ४.
हिरण्यऽशिप्राः २. ३४, ३.
हिरण्यऽशृंगः १. १६३, ९.
हिरण्यऽसंदृक् २. ३५, १०.
हिरण्यऽसंदृशः ६. १६, ३८; ८. ५, ३८.
हिरण्यऽस्तूपः १०. १४९, ५.
हिरण्यस्यऽइव १. ११७, १२.
हिरण्यऽहस्तः १. ३५, १०.
हिरण्यऽहस्तं १. ११६, १३; २४.
हिरण्या ४. १७, ११; ९. ९७, ५०.
हिरण्यानां ४. ३२, १९.
हिरण्यानि १. १६२, १६.
हिरण्येन १. ३३, ८.
हिरण्यैः १. १२२, २; २. ३३, ९; ५. ६०, ४; ७. ९०, ६.
हिरिऽशिप्रः २. २, ५; ६. २९, ६.
हिरिऽश्मश्रुः ५. ७, ७.
हिरिऽश्मश्रुं १०. ४६, ५.
हिरीमशः १०. १०५, ७.
हिरीमान् १०. १०५, ७.
हिरुक् १. १६४, ३२.
हिषे ७. ७, १.
हीना १०. ३४, १०.
हीयतां ६. ५२, १; ७. १०४, १०.
हीये १०. ३४, ५.
हीळः ८. १८, १९.
हीळितः १. ८०, ५.
हीळितस्य ७. ४६, ४.
हुतासः ६. ५०, १५.
हुरः ४. ३, १३.
हुरःऽचितः ९. ९८, ११.
हुरःऽचितं १. ४२, ३.
हुरुक् ९. ७७, ५.
हुवत् ८. २६, १६.
हुवतः ६. २१, १०.
हुवध्यै १. १२२, ४; ५; ५. ४१, ३; ४३, ८; ४५, ४.
हुवन्यति १. ११९, ९.
हुवानः ३. ४१, १; ५. ४३, १०; १३; ६. २१, १०; ७. ७, ३; २०, ३; ८. ७४, १३; १०. ११२, ३.
हुवानाः ४. १, १३; ६. ५०, १४.
हुवामहे ५. ५६, ८; १०. ५७, ३.
हुवे १. १७, ७; ९; ३०, ९²; ७६, ४; १३८, २; १८१, ९; १८५, ३; ६; २. ४, १; ३८, ९; ५. ४६, ३; ७३, २; ६. ५, १; ५०, १; ७. ४२, २; ६१, ६; ६७, ४; ८. १, १०; ५, २४; १०, ५; २२, १५; ३२, ४; ५८, ३; ६५, ३; ६६, १; १०२, ५.
हुवे १. २, ७; २३, ५; १११, ४; ११९, १; २. २९, १; ३२, ४; ३७, २; ३. १२, ४; २०, ५; ५. १८, ३; ४०, ३; ५६, ९; ६. ४५, ७; १९; ६०, ४; १३; ६२, १; ७. १६, १; ३२, ३; ४४, १; ५६, १०; ६५, १; ८. १०, २; ३; २३, ७; २६, १; ३५, २२; ४४, १३; ६८, ४; ७६, १; ९४, १०–१२; १०२, ४; ६; ९. ५, ७; ९; १०. १४, ५; १९, ४; ३६, १; ६१, ४; ६६, १; १५०, ४.
हुवेम ६. ५७, १; ८. ६०, १७.
हुवेम १. १२७, २; १८०, १०; १८४, १; २. १७, ८; ३. ३०, २२; ४७, ५; ४. १६, १६; ६. १९, ४; ४९, १०; ७. ४१, १; २; ४४, २; ७१, १; ९०, ७; ९७, ५; ८. २३, २०; २७, १३; ९६, २०; ९. ६८, १०; १०. ६३, ११; ८१, ७; १२६, ५; १६०, ५; १७८, १.
हुवेय ८. ९, १३.
हूतः ४. १५, ७; १०. ८४, २; १०७, ५.
हूतासः ६. ५०, ४.
हूमहे ८. २६, २४.
हूमहे १. १०, १०; ८९, ३; ५; ५. ३५, ३; ६. ४६, ३; ६; ८. ५१, ५; ८३, ६.
हूयते १. ३४, १०; १०१, ६.
हूयते १. २६, ६; ३६, ६; १३५, २; ५. ६, ५; ८. ८२, ५; १०. १५१, १.
हूयंते ८. ७६, ८.
हूयमानः १. १०४, ९; २. १८, ४;

४. २९, २; ५. ४३, ५; १०. २८, ३; ११६, १; १२२, ५.
हूयमानं ४. २३, ३.
हूयमाना ४. ४३, ४; ६. ६७, ३; ७. ६८, ८.
हूयमानाः २. ३, ५; ४. ३४, ६.
हूयसे ३. ४०, ९; ८. ४, १.
हूयसे १. १९, १; ८. १७, १२; २१, १४; ८२, ४.
हृणानस्य १. २५, २.
हृणायंतं १. १३२, ४.
हृणीतां ८. १०३, १२.
हृणीते ७. ८६, ३.
हृणीथाः ८. २, १९.
हृणीयमानः ५. २, ८.
हृणीषे २. ३३, १५.
हृणीषे ७. १०४, १४.
हृत्तः १०. ११, ६.
हृत्ऽभिः १. ११६, १७; ८. ४३, ३१.
हृत्ऽरोगं १. ५०, ११.
हृत्ऽसु १. १६८, ३; १७९, ५; ५. ८५, २; ८. २, १२; १८, १५; ४८, १२; १०. ४०, १२; ६४, २; १०३, १२.
हृत्सुऽअसः १. ८४, १६.
हृदः १. २४, १२; ६०, ३; २. ३५, २; ३. ३९, १; ५. ३१, ९; ७. १०१, ५; १०. ५, १.
हृदंऽसनिः ९. ६१, १४.
हृदयं ६. ५३, ८; १०. १०, १३; ३४, ९; ९५, १७.
हृदयऽविधः १. २४, ८.
हृदयस्य ७. ३३, ९.
हृदया ६. ५३, ५; ७.
हृदयात् १०. १६३, ३.
हृदयानि १०. ८५, ४७; ९५, १५; १९१, ४.
हृदये १. १२२, ९; ६. ९, ६; १०. ८७, ४; १३.
हृदयेषु १०. ८४, ७.
हृदय्यया १०. १५१, ४.
हृदा १. ६१, २; ६७, २; १०५, १५; १४६, ४; १७१, २; ३. २६, ८; ४. ५८, ६; ५. ४, १०; ५६, २; ६. १६, ४७; २८, ५; ७. ९८, २; ८. २०, १८; ७६, ८; ७७, ९; ९. ५३, २; १०. ७१, ८; ९१, १४; ११९, ५; १२३, ६; १७७, १.
हृदि १. ३२, १४; ९१, १३; २. २३, १६; ३. ४२, ८; ४. ४१, १; ४३, १; ५८, ११; ६. ५३, ६; ७. ८६, ८; ९. ७३, ८; १०. ३२, ९; ९१, १३; १२९, ४.
हृदिऽस्पृक् १. १६, ७.
हृदिऽस्पृशः १०. २५, २; ४७, ७.
हृदिऽस्पृशं ४. १०, १.
हृदे १. ४३, १; ७३, १०; ४. ३७, २; ५. ११, ५; ८. १७, ६; ४८, ४; ७९, ७; ८२, ३; १००, ५; ९. ७२, ७; ८६, २१; १०. ८६, १५; ९७, १८; १८६, १.
हर्यं ५. ४२, २.
हर्या १०. ७३, ६.
हर्यात् ४. ५८, ५.
हृषितं १. १०३, ७.
हृषीवतः १. १२७, ६.
हृषींऽवंतः २. ३१, १.
हृष्यति १०. ८६, ७.
हेत १०. ३०, ९.
हेतयः १. १९०, ४; ८. ५०, २.
हेतारः ९. ६२, ६.
हेतारं ८. ९९, ७.
हेतिः २. ३३, १४; ६. १८, १०; २८, ७; ८. ६७, २०; १०. ८९, १२; १६५, २; ३.
हेतिं १. १०३, ३; १२१, १०; ३. ३०, १७; ६. ५२, ३; ६२, ९; ७५, १४; १०. १४२, ३.
हेतीः ८. ६१, १६.
हेतृऽभिः ९. १३, ६; ६४, २९.
हेतोः १०. ३४, २.
हेत्याः १०. ८७, १९.
हेत्वः ७. ४३, २.
हेमनां ९. ९७, १.
हेमंतान् १०. १६१, ४.
हेम्याऽवान् ४. २, ८.
हेळः १. २४, १४; ९४, १२; ११४, ४; १७१, १; ४. १, ४; ६. ६२, ८; ७. ८४, २.
हेळांसि ६. ४८, १०.
हेळे ७. ६२, ४.
हेषऽक्रतवः ३. २६, ५.
हेषंतं ५. ८४, २.
हेषसा १०. ८९, १२.
हेषस्वतः ६. ३, ३.
होर्तः ३. २, ६; ४. ४, ११; ५. १०, ७; ६. ५२, १२; ८. ४३, १२.
होतः १. २६, ५; २. ६, ६; ३६, ४; ३. १, २२; ७, ९; ४. ६, १; ६. ४, १; ५, २; १०, २; ११, १; ६; ७. १४, २; १०. ६१, १४; ११०, ९.
होतरिति १. १३, १; ३. २१, १; २९, १६; ५. २, ७.
होतरिति १. ७६, ५; ३. २९, ८; ६. १५, १४; ८. ६०, १४.
होता १. १, ५; १२, ३; १३, ४; १४, ९; ११; २६, २; ७; ३६, ५; ५८, १; ३; ५९, ४; ६०, २; ४; ६७, १; ६८, ४; ७०, ४; ७६, २; ७७, १; २; ७९, १२; ९४, ६; १०५, १४; ११७, १; १२७, १०; १२८, १^{२}; १३९, १०; १४१, १२; १४३, १; १४४, १; १४९, ४; ५; १५१, ७; १५३, २; ३; १६२, ५; १७३, २; ३; १८०, ९; २. २, ५; ३, १; ५, १; ७, ६; ९, १; १८, २; ३६, ६; ३. ३, २; ४, ४; १०; ५, ४; ६, १०; १०, ७; ११, १; १४, १; १७, ५; २७, ७; ४१, २; ५५, ७; ४. १, ८; २, १; ६, २; ४; ५; ७, १; ८, ४; ९, ३; १५, १; १७, १५; २१, ५; ६; ४०, ५; ४१, १; ५. १, २; ५; ६; ९, २; ११, २; १३, ३; ४; १६, २; २२, १; ४१, ५; ४४, ३; ४९, ४; ६. १, १; २; ६; २, १०; ९, ४; ११, २; १२, १; १५, १३; १६, १; ९; १०; २३; २१, ४; ४९, ९; ५१, १२;

६२, ४; ६३, ४; ७. १, १६; ७, ३; ५; ८, २; ९, १; २; ११, १; १६, ५; ३०, ३; ३९, १; ४२, ३; ५६, १८; ७३,२; ८५,४; ८. ११, १०; १९, २४; २३, १०; ३४, ८; ३९, ५; ६०, ३; ७१, ११; ७२, २; ७५, १; १०३, ६; ९. ९२, ६; ९७, १; १०. १, ४; २, ३; ५; ६, ४; १२, १; २; २९, १; ४६, १; ५२, १–३; ५३, २; ६१, १४; ७०, ३; ८१, १; ८३, २; ८८, ४; ९१, १; ११; १०९, २; ११०, ३; १२२, १; १७६, ३.

होताऽइव १. २५, १७; ७३, १; ५. ४३, ३; ७. १८, २२; ८. १२, ३३; ९४, ६; ९. ९२, २; ९७, ४७.

होतारः ८. ६०, १६; ७२, ९; ९. १०, ७; ९७, २६; ११४, ३; १०. १२८, ३.

होतारं १. १, १; १२, १; २६, ३; ४४, ७; ११; ४५, ७; ५८, ६; ७; १२७, १; २; १२८, ८[२]; १४१, ६; १४८, १; २. २, १; ३. २, १; १५; ४, ३; ६, ३; ९, ९; १०, २; १३, ५; १९, १; ५; ४. १, १९; ३, १; ६, ११; ७, ५; ५. १, ७; ४, ३; २०, ३; २३, ३; २५,२; २६, ४; ६. ६, १; १४, २; १५, ४; ७; १६, ४६; ७. १०, ५; १६, १२; ८. १९, ३; २३, ७; १७; ४३, २०; ४४, ६; ७; १०; ६०, १; १७; १०. १, ५; ७, ५; ११, ३; ४; २१, १; ४६, ८; ९१, ८; ९; ९२, १.

होतारा १. १३, ८; १४२, ८; १८८, ७; २. ३, ७; ३. ४, ७; ५. ५, ७; ९. ५, ७.

होतारौ १०. ६५, १०.

होतुः १. १६४, १; ३. ६, ७; ३५, १०; ४. २३, १; ९. ९५, ५; १०. ८८, १९; ९४, २; ११०, ११.

होतृऽभिः ३. १०, ४; १०. ६३, ७.

होतृऽमंतं १०. ४१, २.

होतृऽवूर्ये १. ३१, ३; ६. ७०, ४.

होतृषु ८. २०, २०.

होतृऽसदने २. ९, १.

होतॄणां ८. १०२, १०; १०. २, १.

होतॄन् २. ३४, १४; १०. ३५, १०; ६१, १.

होत्रं १. ७६, ४; २. १, २; ३. १७, २; १०. ५३, ४; ५; ९८, ४; ५.

होत्रया १. १२९, ७; १५१, ३.

होत्रऽवाहं ५. २६, ७.

होत्रा १. १८, ८; १२०, १; १४२, ९; २. १, ११; ३. ६२, ३; ४. २, १०; १०. ६४, १५.

होत्राः ४. ४८, १; ५. ८१, १; ८. ९३, २३; १०. १७, ११.

होत्राणि ३. ४, ५.

होत्रात् २. ३६, १; ३७, १[२]; ४; १०. ५१, ४.

होत्राभिः १. ३६, ७; १२२, ९; २. २, ८; ७. ६०, ९; ८. १२, २०; ५३, ७; ५४, ६; १०. ११, ५.

होत्रां १. २२, १०; ७. १०४, ६; ८. १०१, ८; १०. ४०, ४; ६३, ७.

होत्राय ६. ११, २; १०. ९८, ७.

होत्राऽविदः १०. १५, ९.

होत्राऽविदं ५. ८, ३.

होत्रियं १. ८३, २.

होत्रे ३. १०, ५.

होमं १. ९, ९; ८४, १८.

होमनि ३. ६०, ७; ८. ६३, ४.

ह्नोषि ६. ४४, १४.

ह्नुतः ८. ३१, ७.

ह्यः ८. ६६, ७; ९९, १; १०. ५५, ५.

ह्नदं १. ५२, ७; ३. ४५, ३; १०. ४३, ७; १०२, ४.

ह्नदाः १०. १४२, ८.

ह्नदाःऽइव ३. ३६, ८; १०. ७१, ७.

ह्नदेऽचक्षुः १०. ९५, ६.

ह्रादुनिं १. ३२, १३.

ह्रादुनिऽवृतः ५. ५४, ३.

ह्नुणाति १. १६६, १२.

ह्नुतः ६. ४, ५; ९. ६१, २७.

ह्रादिकाऽवति १०. १६, १४.

ह्रादिके १०. १६, १४.

व्हय ५. ५३, १६.

व्हयति १०. १४६, ४.

व्हयंति १०. १६०, २.

व्हयंते १०. ११२, ७.

व्हयंते १. १०२, ६; ४. २४, ३; ३९, ५; १०. ४२, ४; ८०, ५.

व्हयामसि ६. २६, १; ३३, ४; ४१, ५.

व्हयामहे १. ४७, १०; ११४, ४; ५; १०. ४०, ४.

व्हयामि १. ३५, १[४]; ६. ४७, ११; ७. ३४, ८.

व्हये १. १३, ३; ७; ८; १०; १२; २१, १; २२, ५; १२; २३, १८; ११२, २४; १६४, २६; ५. ५६, १; ५; १०. ३६, ७; १०१, १.

व्हरः २. २३, ६; ५. २०, २.

व्हरंते १. १४१, १.

व्हरांसि ६. ४८, १०; ९. ३, २; ६३, ४; १०६, १३.

व्हारः १. १४१, ७; १८०, ३.

व्हारे २. २, ४.

व्हार्यः ६. २, ८.

व्हार्याणां ५. ९, ४.